THE

STUDENT'S ENGLISH-SANSKRIT DICTIONARY

BY

VAMAN SHIVRAM APTE, M.A.,

Author of the "Practical" and "Student's" Sanskrit-English Dictionaries, "Student's Guide to Sanskrit Composition" &c. &c.,

LATE PRINCIPAL AND PROFESSOR OF SANSKRIT, FERGUSSON COLLEGE, POONA

भारतीयाधिशासनसंरक्षकतायां प्रकाशितम्

Published under the auspices of Govt. of India

SOLE DISTRIBUTORS :

MOTILAL BANARSIDASS

DELHI :: PATNA :: VARANASI

PRINTERS & PUBLISHERS :
SHANTILAL JAIN
SHRI JAINENDRA PRESS,
Bungalow Road, Jawahar Nagar,
Delhi-6.

THIS DICTIONARY HAS BEEN PUBLISHED WITH THE SUBSIDY GIVEN BY THE MINISTRY OF EDUCATION, GOVT. OF INDIA.

Price Rs. 4.00

1963

Books available at :

1. **MOTILAL BANARSIDASS**, Bungalow Road, Jawahar Nagar, P. B. 1586, Delhi-6.
2. **MOTILAL BANARSIDASS**, Nepali Khapra, P. B. 75, Varanasi.
3. **MOTILAL BANARSIDASS**, Bankipur, Patna.

FOREWORD

Looking to the great demand for a cheaper edition of Apte's Student's English-Sanskrit Dictionary, the Ministry of Education, Government of India have sponsored and subsidised its reprint through the offset process, bringing down the price of the book from Rs. 12/- to Rs. 4/- only.

It is hoped that the students of Sanskrit all over the country will take the fullest advantage of this reprint.

R. P. Naik

Ministry of Education,
NEW DELHI.

Publisher's Preface to the Third Edition.

In preparing this edition, extreme care has been taken to make a thorough revision of the book, the main features of which are :—

(a) Over a thousand new words frequently occurring in the English literature but not given in the previous editions ave now been added with their appropriate Sanskrit quivalents.

(b) In some cases, Sanskrit equivalents of words in senses other than those given in the earlier editions have been supplied.

(c) Words similar in form but different in sense, and also their derivatives were mixed up in the earlier editions to save sp ce. But as this was found to interfere greatly with clearness and facility of reference they have now been separately given in some cases to remedy the inconvenience.

(d) The feminine forms of adjectives ending in त्, न्, anu स् which are regularly formed by the simple addition of ई were given in the previous editions in the case of the first three letters, and then discontinued. They have now been deleted throughout.

In making these changes, the original plan of the learned author has been strictly followed.

These additions and alterations will be found to have considerably added to the usefulness of the book, and it is hoped that in its present form, it will be more helpful to the student world.

PREFACE TO THE FIRST EDITION.

When I prepared "The Student's Hand-Book of Progressive Exercises," Part II., I thought of adding to it a glossary of difficult words and expressions in the Exercises. When this was done, an idea occurred that the Glossary should be made to include all words of ordinary occurrence, such as are given in small School-Dictionaries. When the revision of the sheets thus written out commenced, and when they were put to a practical test, it was found that several words and expressions had still been left out. I, then, resolved to prepare an English-Sanskrit Dictionary as complete as possible, and the following pages are the result. The Dictionary has thus passed through different stages, and has assumed this form, far exceeding the limits which I had first assigned to it.

Much need not, I think, be said with regard to the necessity of a work like this. In these days of literary activity, when the attention of students is drawn more and more to the study of Sanskrit, it is necessary that all appliances should be ready before them to facilitate this study. There are one or two small Sanskrit-English Dictionaries, though not quite adequate to meet the wants of advanced students of Sanskrit, but there is no English-Sanskrit Dictionary such as will be within their easy reach. The Dictionaries of this description that I know of, are two in number: one by Professor Monier Williams, and another by Mr. Anundoram Borooah of Calcutta. Both these Dictionaries, though valuable in themselves, are not accesible to the student, the prices being prohibitively high. But there are other considerations which make these works not quite adapted to his wants. Professor Monier Williams' Dictionary, having been compiled nearly 35 years ago, chiefly by inverting the then existing Sanskrit-English Dictionaries, is naturall open to the fault of being often not *practical.* As he says the Preface to his Dictionary, he proceeded to translat Webster's Dictionary systematically into Sanskrit, omitting words, phrases &c. of which no classical equivalent could b found or suggested. The result has been that many of hi synonyms appear more as coined words than classical expres sions used by standard Sanskrit authors. With regard to word

collected in Lexicons, such as Amarakosha, Medini, Sabdakalpadruma, there is no difficulty; but in the case of those words and expressions which can only be suggested by a careful study of the usage of the best authors, the work, in my humble opinion, falls short of one's expectations. Mr. Anundoram Borooah's work is eminently *practical* : it abounds with quotations from several standard authors ; the renderings are generally happy, and the work has, at east, a classical appearance. The fondness for giving quotations has induced the writer to give several quotations for illustrating such words as यत्र, इति, तत्र, च &c., of the meanings of which there is no doubt nor is any confirmation needed. But one great defect of his otherwise very useful work is that it gives too few equivalents. He has pursued the course of referring one word to another, but this is, in some cases, carried to such an extent, that when a word, as directed, is referred to another, that again is referred to some other word of a synonymous nature, which in its turn is referred to another till the reader returns to the original word, apparently without having his labours rewarded. A study of Mr. Borooah's work is a good treat for an advanced Sanskrit scholar, but will not, I believe, satisfy the student. From considerations like these I thought I should be doing some service to the Sanskrit reading public, if I compiled an English-Sanskrit Dictionary adapted to the wants of the student. The foregoing remarks are made not with the view of detracting from the high and acknowledged merits of the two works, but solely to indicate the line I have followed, and the object I have had in compiling this work.

Some words are now necessary as to the plan and scope of the Dictionary. When I resolved to make this Dictionary as complete as possible, consistently with its aim of being useful for the student, I took the latest edition of Webster's Complete Dictionary, and taking that as my basis, proceeded with the work of compilation. As I advanced, I found that several words, phrases and expressions and several senses of single words, could not be adeqarely represented in Sanskrit so as to appear like Sanskrit, either because the words &c. were purely technical and referred to specific ideas in subjects, such as Chemistry, Botany, Medicine, Psychology, Law, Engineering &c., or were such as had no corresponding ideas in Sanskrit and were peculiar to the English language. Words of this nature

are numerous in Webster's Dictionary, and I have omitted them, including also obsolete and rare words or senses of words. Several words of obvious signification, such as those formed by the prefixes. '*in*, '' *mis*, '' *pre* ' '*un*,' are also omitted, as they may be easily formed from their second member. But the general terms of all sciences have been included, and of technical terms such as could be duly represented by Sanskrit equivalents actually existing in the language or by short, wieldy new combinations of words have been inserted. Of this description are words like Telegram, Democrat, Society, Literature, Address (of a letter) and several other words which have a peculiar sense in English and have to be translated by inventing equivalents. English, like many other languages, has so many expressions and idioms peculiar to itself, so many shades and nice distinctions of meaning, and so many new formations of words, progressing with the progress of the language, that it would be impossible to embrace them all in an English-Sanskrit Dictionary, even if it were the most comprehensive work, much more so, in a work designed principally for students. Take the words Line, Pass, Strong. Webster gives 21 senses under 'Line,' 13 under 'Pass (*v. i.*)' and 20 under 'Strong.' Some of these are technical, and some are not *different* senses as such, but shades of meaning or particularities of use; most of which may be translated by the words given for the general sense, (*see* the words). I have not thought it desirable, like Professor Monier Williams, to insert words the English explanation of which has to be systematically translated, in order to give some idea of their meaning. 'Indian-rubber' is translated by अतिस्थितिस्थापकविशिष्टो भारतदेशीयवृक्षनिर्यासः; 'Shuttle cock' by क्षुद्रगुलिकाविशेषः यो विनोदार्थं दण्डाहतो भूत्वा इतस्ततः प्रक्षिप्यते; and many others of this nature, which can be translated by विशेषः 'a kind of tree, flower, fruit' &c. Such words may be retained by the student in their English form, or their meaning may be translated if he desire to have them in a Sanskrit garb. स्पंजः 'Sponge,' डुकः 'Duke,' साबनं 'Soap,' लाटिनं 'Latinity' (as given by Mr. Boroosh) may, I think, be very safely omitted even in a comprehensive Dictionary.

To turn now to the plan and arrangement of the work. The most striking feature of the arrangement is that a word in its different parts of speech, compound words derived from it, derivatives formed from it either regularly, by means of terminations (*e. g.* ed, ing, ly, ness &c.)

or irregularly, have been given together, the derivatives being arranged in order under the root or primitive word, by means of small black dashes. The dashes are intended to at once strike the eye and to direct it to the word after it ; and when the "directions to the student" are remembered, there, will, I believe, be no difficulty in referring words to the Dictionary. The principle of the arrangement is to give words according to the root-system ; words regularly derived will, of course, be referred in their proper places ; but words formed from the radical irregularly should also be referred under that radical. 'Abstemious.' should be referred under 'Abstain,' 'Perception' under, 'Perceive, 'Death,' 'Dead,' under 'Die,' 'Strength' &c., under 'Strong,' 'Would,' under 'Will,' and so on ; where it is not likely for the student to know where such words are given, reference is made to those places : *e. g.* see Material, Sight. One of the greatest advantages of the system has been practically (whatever it may be theoretically) to effect a very large saving of space. To give the reader an idea of the vast saving effected by this system, it may be stated that, if the words in their different parts of speech and their compounds and derivatives were separately given, as in Monier Williams' Dictionary, they would cover nearly 800 pages of this size, or 1, 000 of the size, style of printing, &c. of Monier Williams' Dictionary. Besides, by giving the words 'Dead' 'Death' under 'Die,' a considerable repetition of words is avoided. About 20 equivalents are given for 'Die,' and only a few are given for 'Dead ; the rest can be formed in the same way from the roots immediately above ; if it were given in its usual place, all words would have to be given or a reference made to 'Die.' My chief aim has been to give a good deal of matter in a small space, and this object is, I believe, considerably secured, as shown by the figures given above ; and I have thus been enabled to give this book to the public at a cheap price.

The next point to be noticed is the number of equivalents that are given for a word. I believe that in an English-Sanskrit Dictionary, it is sufficient to give such words only as are of very frequent occurrence in Sanskrit authors. It cannot include all words in the language, and even if it could, it would be of no great use, since many of the words would be found to be very rarely used. The word 'Gold' has over 50 synonyms given for it in the different lexicons ; 'Sun' has

nearly a hundred. But it will easily be seen that, excepting some, the synonyms are either combinations of simple words or are descriptive epithets. Of this class are the words वक्रपुच्छः, ललजिह्वः, रात्रिजागरः, for 'Dog.' Mr. Borooah in his Dictionary has given only a few equivalents, in some instances, only one, where there were 5 most commonly used; Prof. Williams has very often given too many equivalents, grouping together common and rare, synonyms proper and epithets. In the former case the student will hardly have any room left for choosing his word, while in the latter, he will be at a loss to see which to choose. In giving equivalents in this Dictionary, whether for Substantives, Adjectives, Adverbs or Verbs, I have endeavoured to strike a middle course between these two courses, and, have kept one principle steadily in view : to give such words as are found frequently used in the works of standard authors. The equivalents are arranged in the order of their frequency of use; and the students, in his ordinary prose composition, would do well to make his selection from the first few equivalents enumerated. In the case of Verbs it has not been possible to maintain this principle with perfect accuracy in every case, but it is generally maintained. It is only in a few cases of substantives that I have gone the length of giving all words enumerated in the Amarakosha; and in the case of names of material substances, names of plants and trees that have been identified, and in a few others, all the words given in the Amarakosha have been here incorporated. care being taken to arrange them in the order of their usefulness. Similarly such Genders, Padas or Conjugations are given as will be found generally used; I have very rarely given all possible ones. It has not been thought necessary to give the 3rd person singular, Present tense, nor all possible derivatives from simple words ; they will have, if necessary, to be made up according to the "Directions" afterwards given. In giving equivalents for a word in its different senses, it has also not been thought necessary to give the meanings in English, except where it was necessary to note a particular sense. One word in Sanskrit often represents several meanings in English, and to render them into Sanskrit, the Sanskrit word has to be repeated. This accounts for the repetition of some Sanskrit words under different meanings.

In will be noticed that there are several sentences given to illustrate the meanings of words, some of which are quotations

from standard authors as will be readily seen from the references given after them; but many of the phrases and sentences that are translated, and are not supported by any authority, are taken from the "Student's Hand-Book of Progressive Exercises," Part II. I deemed it essential to illustrate, in some cases at least, the *construction* of he equivalents given, wherever it was peculiar in Sanskrit; and I thought I could do this better if I gave sentences from classical authors instead of framing them myself. The quotations have become quite necessary in those cases where equivalents have been here suggested for the first time; I thought I should produce my vouchers for a particular word that I suggested rather than leave the reader in doubt as to its genuineness. In a few cases the English or Sanskrit sentences are closely translated; in a few others only such parts of the Sanskrit sentences are translated as are sufficient to illustrate the word intended to be illustrated, while in several cases, Sanskrit sentences alone are given which might be readily understood by the student. On a reference to the names of works or authors drawn upon for quotations, it will be found that the list is not very comprehensive; several large and useful works have been left out, and works falling in the range of classical literature excluded. But my principal aim in giving quotations has been to supply the student with good expressions from works *within his easy reach* so that he might study, if necessary, the particular places referred to. Kalidasa's works and Bana's Kadambari are more frequently drawn upon than the Ramayana, the Mahabhharata, the Naishadha or the Mahâvîracharita.

An attempt has been made to avoid as much unnecessary repetition as was possible, without marring the usefulness of the work. A Dictionary is necessarily a work of repetition; several words have to be unavoidably repeated, howsoever unwilling one might be to do so. I have thought it necessary to make reference under some words to preceding or succeeding parts of the Dictionary, chiefly with the view of avoiding repetition; but in such cases a few equivalents are given, and the student is told to follow out the reference, if he want to know more about the word. Take, for instance, the words, Beguile, Cheat, Deceive, Delude, Defraud, Impose upon, Take in; or Blame, Censure, Reprove, Reproach, Scold, Reprimand, Reprehend; or Path, Road, Way: these words, whatever be their shades of meaning in English, are, when represented in

Sanskrit, almost synonymous, and may be conveniently represented by the same words. If ten or fifteen equivalents under one of these words, say, Cheat, Censure, or Way, are given, it would be unnecessary to repeat all of them again under the synonymous words. In all such cases, therefore, references have been made to some general word under which are given all the equivalents. In a few cases the reference has been made, not for any equivalents, but for any expressions, phrases, idioms &c. that may have been given under the principal word. In no case will the student have to refer to the Dictionary *more than twice.*

In a work which professes to deal with the phrases and expressions of the English Language, the writer cannot afford to disregard the several small useful proverbs, mottoes, or other expressions which have become proverbial. I have, with this view, inserted, under some principal word therein, such proverbs &c., and have given exact or approximate equivalents, wherever they existed in Sanskrit, and have in a few cases given my own translation of them. Of this nature are proverbs given under Bush, Handsome, Make, Oil, Race, Something, Suffer, Touch &c.

With regard to the method of writing the Sanskrit equivalents, an objection might possibly be raised. Throughout the work the usual practice of representing every anusvara in the body of a word by its corresponding nasals has been rejected and the anusvara sign is invariably used, where usually a nasal would stand. I have not been able to understand the principle on which scholars reject this system and betake themselves solely to the other; though the anusvara system is most convenient in printing, and occasionally saves much misunderstanding. Besides, it is a practice generally followed in our old Manuscripts, and is sanctioned by Panini as being optional. For these reasons I have scrupulously followed it in this Dictionary, but more especially because it is very convenient in printing. The rules of Sandhi, to make the words clearly intelligible, are not in all cases strictly observed.

It now remains for me to do the grateful duty of acknowledging my obligations to those that have assisted me in the preparation of the Dictionary in one form or another. Foremost among them stand the works of Mr. Boroosh and Prof. Williams, both of which I have most frequently consult-

ed. Monier Williams' Dictionary, though inferior in several respects to Mr. Borooah's, has several happy renderings of short words and expressions, especially where ideas, purely English, have to be clothed in a Sanskrit garb, and I have freely consulted his Dictionary for such renderings. I have also frequently referred to the learned Professor's valuable Sanskrit-English Dictionary; for both of which my sincere thanks are due to him. But my acknowledgments are chiefly due to Mr. Borooah, from whose work I have derived much substantial assistance, in the suggestion of equivalents for words or phrases, more particularly from his numerous quotations, and therein again, quotations from such works as were not accessible to me, or being accessible, I had no time at my disposal sufficient to go through them. I have also had to keep constantly by my side, the useful Sanskrit Lexicon—the Kosha of Amarasimha—made more useful by the edition published by the Department of Public Instruction, Bombay. In giving illustrative sentences from classical Authors, I have used annotations or translations wherever they existed, and have derived hints from them and have occasionally adopted their translation. My thanks are due to all annotators, editors or translators of such works. I have to thank sincerely Prof. R. G. Bhandarkar, M.A., Deccan College, Poona, who kindly proposed suitable equivalents for some difficult words and phrases which were referred to him. I have also to thank my friend, Mr. Ganesh Krishna Garde, L. M. & S., for having supplied me with accurate equivalents for some knotty and technical terms in Medicine, from books and sources which I had no time to reach, and which even if I had time to reach and use, I could not, unaided by him, turn to much practical account. Lastly, my thanks are due to several kind and obliging friends who assisted me either in collecting materials for the Dictionary, or in carrying it through the Press.

In conclusion, I trust that the Dictionary will be useful not only to those for whose use it is principally prepared, but to the general public also who may wish to avail themselves of appliances calculated to help the study of Sanskrit. It is my belief that, except for the translation of passages from purely technical subjects, such as Chemistry, Botany, Medicine, Philosophy etc., this Dictionary will be useful to all readers of Sanskrit for translating any passage dealing with ordinary subjects. None is more conscious than myself of the defects of the book, and of the mistakes or inaccuracies that might have crept into it, in spite of my vigilance; and when a second edition is prepared, I shall endeavour, to the best of my ability, to make the Dictionary complete in itself. I shall be very happy to receive any suggestions that readers may have to make and shall be but too willing to adopt them, if I find them useful. With these prefatory remarks I leave the work to the indulgent judgment of the public.

Poona, June, 11th, 1884. V. S. A.

DIRECTIONS TO THE STUDENT.

(To be studied before using the Dictionary.)

1. Words and their derivatives are arranged in the following order : first the radical or primitive word, in all its different parts of speech; then compound words, arranged in alphabetical order; (in the case of verbs, such words as Break off, Turn out, are given as -off, -out); and then the derivatives which are always distinguished by a black dash; those formed regularly being given first and the irregular ones, written fully, after them (*see* Ambition, Humble, Young).

Note—This order is not regularly observed in the first three letters, compound words and derivatives being, in a few cases, both distinguished by black dashes.

2. In giving the terminations by which derivatives are formed, the changes which the final and initial letters undergo, *e. g.* the dropping, doubling or assimilation of letters are assumed; the terminations being always given in their original form; *see* Cut, Hurry, Mature.

3. (*a*) A small black dash (-) marks the commencement of a new derivative. (*b*) A word preceded by a large black dash (—) indicates that the derivatives given after it, are from that word and *not* from the radical or primitive word; *see* Die, Dead. (*c*) A hyphen used in the middle of Sanskrit words indicates that each of the members separated by the hyphen is to be repeated with the word after it; or that the word after the hyphen is to be taken as an alternative for the word immediately before it (to be, in some cases, decided by the context), *e. g.* in HAVE, *l.* 9, यथाकामं-स्वरुच्या वृत् means यथाकामं वृत्, स्वरुच्या वृत्; in Practice, *l.* 3, नित्यवृत्तिः-चर्या अनुष्ठानं means नित्यवृत्तिः, नित्यचर्या, नित्यानुष्ठानं. (*d*) A hyphen followed by a comma (-,) indicates that the word after it may stand by itself or may be joined with the word before it; *e. g.* in Place *l.* 1, प्र-,देशः means the words is either देशः or प्रदेशः; (*e*) A comma followed by a hyphen (,-) indicates that the word after it may be compounded with the word preceding it; *e.g.* in Stage, *l.* 1, रंगः-,शाला means the word is either रंगः, or रंगशाला. (*f.*)° denotes that the word immediately before it which is separated by a comma, may be compounded with the words which it connects; *e. g.* Prevent, *l.* 1. वृ- c., नि-विनि,° means the root is also निवृ c. and विनिवृ c.

4. In the case of substantives, the nominative case, wherever it could at once indicate the gender, has been given; the visarga thus indicates masculine gender, and anusvara neuter gender. Where the nominative is not indicative of the gender, it is given as *m.*, *f.*, *n.*, as the case may be. All substantives ending in consonants have their genders specified as *m.*, *f.*, or *n.*

5. *In the case of adjectives, the simple base only is given. The feminine of the majority of adjectives in* अ *ends in, and adjectives ending in* इ, उ *have generally the same base for all genders. In all such cases the simple base is given,* the genders being formed regularly according to similar substantive bases. Irregular feminines are denoted in brackets. (*f.*) Bases ending in त्, न्, स्, form their feminine regularly in ती, नी सी,

6. (*a*) In the case of verbs, the Arabic figure denotes the conjugation to which the root belongs; P denoting Parasmaipada, A Atmanepada, and U Ubhayapada (P & A). Roots of the tenth conjugation belong to both Padas, theoretically at least; and hence 10 is used for all roots of this conjugation, though the Parasmaipada, unless where otherwise specified, should be generally preferred for use. (*b*) c. denotes causal, and is formed from roots by making the same changes as in the 10th conjugation. Wherever it cannot be formed by this general rule, it is shown in brackets. (*e*) D. means Denominatives; here the 3rd pers. singular Present tense is given throughout.

7. All the derivatives from a word are not always given when they may be easily supplied; more especially, in the case of potential passive participles, formed by तव्य, य, अनीय, past participles, present participles, verbal nouns, abstract nouns from adjectives, and adverbs from adjectives. Where there was any peculiarity in the formation of these derivatives, they are given, but in many cases the student will have to supply the forms, according to rules given in grammars.

ABBREVIATIONS

A.

Of Grammatical Terms & c.

A	Atmanepada
a.	Adjective
abl.	Ablative
acc	Accusative
adv.	Adverb
Arith.	Arithmetic
Bah.	Bahuvrihi
c.	Causal
circum.	Circumlocution
comp.	Compound
conj.	Conjunction
D.	Denominative
dat.	Dative
deriv.	Derivative
desid.	Desiderative
ex.	Expressed
f.	Feminine
fig.	Figurative
freq.	Frequentative
gen.	Genitive, Generally (when followed by ex)
gen.abs.	Genitive absolute
ind.	Indeclinable
inf.	Infinitive
instr.	Instrumental
interj.	Interjection
lit.	Literal, literally
loc.	Locative
loc.abs.	Locative absolute
m.	Masculine
Math.	Mathematics
n.	Neuter
nom.	Nominative
P.	Parasmaipada
Part.	Participle
pass.	Passive
pot.	Potential
pot.pass. par.	Potential Passive participle
pl.	Plural
pr.	Prefixed
prep.	Preposition
pron.	Pronoun
pron. a.	Pronominal adjective.
q.v.	Quod vide, which see
s.	Substantive
sim.comp.	Similar compound
Tat.	Tatpurusha
U.	Ubhayapada (Parasmaipada and Atmanepada)
v.	Verb (transitive and intransitive)
v. i.	Verb intransitive
voc.	Vocative
v. t.	Verb transitive

B.

Of the names of Works.

N. B.—where a Roman figure is followed by an Arabic figure, the former refers to the canto or chapter, and the latter, to the number of the veres; Arabic figures in the case of dramas &c. refer to the act or page.

Bh.	Bhartrihari, II denoting Nitishataka and III Vairagvashataka (Bombay Edition.)
D.K.	Dashakumaracharita, I denoting the Purvapithika, and II the Uttarapithika, and the Arabic figure, the number of the story
H.	Hitopadesha, the Arabic figures denoting the four parts in their order
K.	Kumarasambhava
Ka.	Kadambari (Bombay Edition)
Kav.	Kavyadarsha
Ki.	Kiratarjuniyam
Li.	Lilavati
M.	Malavikagnimitra (Bombay Edition)
Mal.	Malatimadhava (Bombay edition)
Mah.	Mahabharata
Me.	Meghaduta (Calcutta edition)
Mn.	Mallinath
Mr.	Mrichchhakatika
Mu.	Mudrarakshasa
N.	Naishadha
P,	Panchatantra, the Roman figure denoting the number of the Tantra and the Arabic, the number of the story (Bombay edition)
R.	Raghuvamsha
Rat.	Ratnavali
S.	Shakuntala
S. B.	Shankar Bhashya
Si.	Sisupalavadha
S. K.	Siddhanta Kaumudi
S. R.	Subhashitaratnabhandagaram
U.	Uttararamacharita
V.	Vikramorvashiyam
V.M.	Vyavahara Mayukha (Mr. Mandlik's edition)
Ve.	Venisamhara
Vi.	Viracharita
Y.	Yajnavalkya.

THE STUDENT'S ENGLISH-SANSKRIT DICTIONARY.

A.

A, An (As an article) not ex.; 'a man' नरः. **2** (One) एकः. **3** (Indefinite) किं with चित्, चन or अपि. **4** With part., ex. by dat. or inf.; 'set out a hunting' मृगयायै or मृगयां कर्तुं प्रतस्थे; 'fell a-weeping' क्रंदितुं प्रवृत्तः. **5** (Every) प्रति in comp., or by repetition of word; '100 Rs. a day' प्रतिदिनं or दिने दिने शतरूपकं. **6** (Species) विशेषः, भेदः, in comp.; 'dog is an animal' श्वा प्राणिविशेषः.

Abandon, *v. t.* त्यज् 1 P, हा 3 P, वि-उत्-सृज् 6 P, उज्झ् 6 P, अपास् 4 P, रह् 1 P, 10, मुच् 6 P. **-ed,** *a.* त्यक्त, हीन, मुक्त &c. **2** पापात्मन्, भ्रष्टचरित; 'he was a. to his fate' दैवाधीनः कृतः, यद्भावि तद्भवतु इत्युक्त्वा स परित्यक्तः. **-ment,** *s.* त्यागः, उत्सर्गः; 'a. of worldly connections' संन्यासः, विरक्ति *f.*

Abase, *v. t.* अभिभू 1 P, स्वस्थानात् निपत् c., अपकृष् 1 P, लघूकृ 8 U. **-ment,** *s.* अपकर्षः, अभिभवः, मानभंगः, अवज्ञानं.

Abash, *v. t.* लज्ज् c., ह्री c. (ह्रेपयति), त्रप् c. (त्रपयति). **-ed,** *a.* लज्जित, त्रपित, विलक्ष, व्रीडित, ह्रीपरिगत; 'with an a. countenance' त्रपाधोमुख (खी *f.*).

Abate, *v. t.* ह्रस् c., लघयति (D.), शम् c. (शमयति). **2** (price) न्यूनीकृ 8 U; अवसद् c. **-***v. i.* क्षि pass., ह्रस् 1 P; प्र-उप-शम् 4 P. **-ment,** *s.* न्यूनीकरणं; ह्रासः, क्षयः.

Abbacy, *s.* मठाधीश-पदं-त्वं.

Abbey, *s.* विहारः, मठः.

Abbot, *s.* मठाध्यक्षः, विहारस्य प्रधानपुरुषः. **-Abbess,** *s.* मठाध्यक्षा, विहारपालिनी.

Abbreviate, *v. t.* सं-प्रतिसं-हृ 1 P, संक्षिप् 6 P, समस् 4 P, ह्रस् c. **-ion,** *s.* संक्षेपः, संक्षेपणं.

Abdicate, *v.* राज्यं or पदं त्यज् 1 P or अपास् 4 P or क्षिप् 6 P. **-ion,** *s.* पदत्यागः, अधिकारत्यागः, स्वेच्छया परित्यागः.

Abdomen, *s.* उदरं, कुक्षि *m.*

Abduct, *v. t.* अपहृ 1 P. **-ion,** *s.* अपहरणं, अपहारः.

Aberration, *s.* भ्रंशः, च्युति *f.*, भ्रेषः, पथभ्रष्टता; 'a. of mind' चित्त or मति-भ्रमः.

Abet, *v. t.* प्रवृत् c., प्रोत्सह् c. **2** उपकृ 8 U, साहाय्यं कृ. **-tor,** *s.* प्रवर्तकः, प्रोत्साहकः.

Abeyance, *s.* विलंबः, व्याक्षेपः.

Abhor, *v. t.* गुप् desid. (जुगुप्सते), बध् desid. (बीभत्सते); (with abl.) गर्ह् 1, 10 A, विद्विष् 2 U. **-rence,** *s.* जुगुप्सा, बीभत्सा, गर्हा, विद्वेषः. **-rent,** *a.* जात-विद्वेष. **2** विरुद्ध, अयुक्त, विपरीत.

Abide, *v. i.* वस् 1 P, स्था 1 P, वृत् 1 A. **-***v. t.* (Wait for) प्रतीक्ष् 1 A, प्रतिपाल् 10. **2** (Endure) सह् 1 A, क्षम् 1 A, 4 P, तिज् desid. (तितिक्षते); 'a. by' स्था (loc.), अनुवृत्; कस्यान्यस्य वा वचसि मया स्थातव्यं (Ks. 156); 'I shall a. by your decision' तव निर्णयमनुवर्तिष्ये, निर्णयानुरोधेन वर्तिष्ये, निर्णये स्थास्यामि; 'a. s by his promise' प्रतिज्ञां-अभिसंधां पालयति. **-ing,** *a.* स्थायिन्; अनुवर्तिन्.

Abject, *a.* अधम, अप-नि-कृष्ट, कृपण, नीच, तिरस्कार्य, *See* **Mean.** **-ness,** *s.* अधमता, कार्पण्यं.

Abjure, *v. t.* सशपथं त्यज् 1 P. **2** प्रत्याख्या 2 P. **-ation,** *s.* सशपथः त्यागः.

Ablative, *s.* पंचमी विभक्ति *f.*

Ablaze, *a.* ज्वलत्, उज्ज्वलत्, प्रदीप्त.

Able, *a.* समर्थ, क्षम, शक्त ; कर्मक्षम, अलंकर्मीण. 2 प्रबल, बलवत्, शक्तिमत्. 3 पटु, निपुण ; 'to be a.' शक् 5 P, पृ c., or पार् 10 U, उत्सह् 1 A, प्रभू 1 P, with inf.; अलं with inf. or dat. of noun ; 'a. to protect' रक्षितुं-रक्षणाय-अलं, प्रभवति &c. **-Ability,** *s.* शक्ति *f.*, बलं, सामर्थ्यं. 2 पाटवं, वैचक्षण्यं ; कर्मक्षमता. 3 धीशक्ति *f.*, मत्युत्कर्षः, मति *f.*, बुद्धि *f.*; 'to the best (utmost) of one's a.' यथाशक्ति, यावच्छक्यं, सर्वप्रयत्नैः. **-Ably,** *adv.* निपुणं, कुशलतया.

Ablution, *s.* प्रक्षालनं, पावनं; स्नानं, मज्जनं.

Abnegation, *s.* प्रत्याख्यानं, संयमः, निग्रहः; 'self-a.' आत्मसंयमः, इंद्रियनिग्रहः. 2 अप-नि-ह्नवः.

Abnormal, *a.* अनियत, नियमविरुद्ध, अपूर्व, विलक्षण.

Aboard, *adv.* अधिनु ; 'go a.' नावमधिरुह् 1 P.

Abode, *s.* गृहं, वेश्मन् *n.*, निवासः, निलयः, आलयः, वसति *f.*, *See* **House.** 2 पदं, आस्पदं, स्थानं, भाजनं ; 'riches are the a. of calamities' संपदः पदं (आस्पदं) आपदां.

Abolish, *v. t.* विलुप् c., निरस् 4 U ; खंड् 10. 2 नश् c., उत्सद् c., उच्छिद् 7 P. **-Abolition,** *s.* लोपः. 2 नाशः, उच्छेदः, निवर्तनं, खंडनं.

Abominate, *v. t.* द्विष् 2 U, गर्ह् 1, 10 A ; *See* **Abhor. -ion,** *s.* गर्हा, विद्वेषः. 2 अशुद्धद्रव्यं, कुत्सास्पदं. **-Abominable,** *a.* द्वेष्य, गर्हणीय, गर्हित. 2 जुगुप्साकर (री *f.*).

Aboriginal, *a.* आद्य, आदिम, पूर्वकालीन.

Aborigines, *s.* आदिमवासिनः (pl.).

Abortion, *s.* गर्भस्रावः-पातः ; 'to cause a.' भ्रूणहत्यां कृ 8 U, 'causing a.' भ्रूणहत्या. **-Abortive,** *a.* गर्भस्राविन्, अपूर्णकाल. 2 अकालकृत, निष्फल, मोघ, व्यर्थ (as an attempt.).

Abound, *v. i.* (with, in) संकॄ-पॄ pass., or by बहु, भूयिष्ठ, in comp. ; भूयिष्ठदुःखं वनं ; बहुकौतुकः स देशः 'a. s in curiosities.' **-ing,** *a.* आढ्य, संकीर्ण, आकुल, प्राय, in comp. **-Abundant,** *a.* बहुल, प्रभूत, प्रचुर, विपुल, भूरि. **-ly,** *adv.* बहुशः, अनेकवारं, विपुलं. **-Abundance,** बाहुल्यं, प्राचुर्यं.

About, *prep.* परि ; परि-इ 'go a.' &c. 2 देशीय (with numerals); 'a. five years old' पंचवर्षदेशीयः. 3 (Regarding) अधिकृत्य, प्रति, उद्दिश्य ; संबद्ध-अधिकृ-गत-विषये in comp. ; 'I ask a. my friend' मित्रगतं पृच्छामि ; पराजयशुचिवृत्ता आलापाः &c. 4 कृते, अर्थे, अर्थं, हेतोः. 5 परितः, अभितः, (acc.); समीपं, समीपे, पार्श्वतः, निकटे, (gen.). 6 (Nearly) with numerals उप, आसन्न, अदूर, in comp ; उपचतुराः 'a. four'. *-adv.* (Showing prospective fut.) ex. by fut. part., उन्मुख (खी *f.*), उद्यत, आसन्न, or desid. ; अनुयास्यन् मुनितनयां (S. 1) 'a. to follow' &c. ; जिघांस्यमानो नरः 'a. to be killed' ; आसन्नमरणः 'a. to die' ; आसन्नराज्यनाशः 'a. to lose the realm'. 2 प्राय-कल्प, in comp.; 'it is a. noon' मध्याह्नप्रायः-कल्पः समयः ; 'what are you a.' किं कर्तुमुद्यतोसि, किंकार्यव्यग्रोसि, किमारंभस्त्वं. 3 परितः, अभितः. 4 इतस्ततः, स्थानात्स्थानं.

Above, *adv.* अधि or अभि pr. ; उपरि, उपरिष्टात्, ऊर्ध्वं ; 'just a.' उपर्युपरि (acc.) *-a.* प्रागुक्त, पूर्वनिर्दिष्ट. *-prep.* उपरि (gen.) ; अति pr ; अधिक, उत्तर, विशिष्ट, (abl.) ; 'a. calculation' अतिसंख्य ; 'he stands a. all' स सर्वेषां मूर्ध्नि तिष्ठति ; 'a. mentioned' पूर्वोक्त, प्रागुक्त ; 'to be a.' ऊर्ध्वं स्था 1 P, अभिभू 1 P. *See* **Excel.**

Abrade, *v. t.* घर्षणेन क्षि 1 P. **-Abrasion,** *s.* घर्षणेन क्षयः.

Abreast, *adv.* पार्श्वपार्श्वि.

Abridge, *v. t.* संक्षिप् 6 P, समस् 4 P, संग्रह् 9 P. **-ment,** *s.* संक्षेपः, सारः, संग्रहः &c.

Abroad, *adv.* विदेशे, देशांतरे. 2 बहिः (abl.). 3 (Widely) सर्वत्र, दूरं ; 'casting a. his rays' दूरप्रसारितकरः (सूर्यः) ; 'live a.' प्रवस् 1 P ; 'go a.' प्रसृ 1 P, बहुलीभू 1 P, प्रकाशतां गम् 1 P, प्रकाशीभू 1 P, निर्गम् 1 P ; 'the dreadful vow became known a.' सा दारुणा प्रतिज्ञा लोके प्रसिद्धाभूत्, लोके प्रकाशतां गता.

Abrogate, *See* **Abolish.**

Abrupt, *a.* विषम, (प्रपातः). 2 आकस्मिक (-की *f.*), असंबंध, अकांड. **-ly,** *adv.* एकपदे, सहसा, अकस्मात्.

Abscess, *s.* विद्रधिः ; स्फोटः, व्रणः-णं.

Abscond, *v. i.* प्रच्छन्न *a.* भू 1 P, आत्मानं गुह् 1 U or प्रच्छद् 10, अंतर्धा pass. 2 पलाय् 1 A, व्यपसृप् 1 P, अपक्रम् 1 U, 4 P.

Absent, *a.* अवर्तमान, अविद्यमान, अनुपस्थित, स्थानांतरगत. 2 प्रोषित. 3 (In mind) हृदयेन असंनिहित, शून्य-हृदय-मानस ; 'to be a.' स्थानांतरे वृत् 1 A, न उपस्था 1 U. **-ee,** *s.* अनुपस्थितः, प्रवासिन् *m.* प्रोषितः.

-Absence, *s.* अनुपस्थिति *f.*, असन्निधि *m.* परोक्षं, परोक्षता. 2 (Non-existence) अभावः. 3 विरहः, वियोगः ; 'in one's a.' परोक्षे ; 'a. of mind' शून्यमनस्कता, शून्यहृदयत्वं. अनवधानं, विगतचेतनत्वं.

Absolute, *a.* संपूर्ण, पर्याप्त. 2 नित्य, परम. 3 (Not relative) केवल, मात्रक, अनन्यसंबद्ध. 4 परम, उत्तम, श्रेष्ठ. 5 अनियत, निर्यंत्रण, स्वाधीन ; 'a. king' सम्राज् *m.*, अधिराज. **-ly,** *adv.* सर्वथा, सर्वशः, केवलं, एकांततः.

Absolve, *v. t.* (पापात् &c.) मुच् 6 P or c., उद्धृ 1 P, 10 ; पापं-अपराधं-क्षम् 1 A. **-Absolution,** *s.* पापमुक्ति *f.*, क्षमा. 2 मुक्ति *f.*, मोक्षः, निःश्रेयसं, अपवर्गः, निर्वाणं, श्रेयस *n.*, कैवल्यं.

Absonant, *a.* विसंवादिन्, विरोधिन्.

Absorb, *v. t.* उत्- ग्रस्, *c.*, निगृ 6 P, आचम 1 P, नि-आ पा 1 P. 2 ग्रस् 1 A, आत्माधीन *a.* कृ 8 U; व्यापृ c., आसंज् c. **-ed,** *a.* नि-,मग्न, आसक्त, निरत, लीन, व्यापृत पर, परायण, in comp. 2 निपीत. **-Absorption,** *s* निपानं. शोषणं ; 'a. into the Supreme Soul' मोक्षः, निर्वाणं ; ब्रह्मणि लयः. ईश्वरसायुज्य.

Abstain, *v. i.* निवृत् 1 A (abl.), परिवृज् 10 (acc.) ; 'has a. ed from eating flesh' निवृत्तमांसो जनकः (U. 4). 2 विरम् 1 P (abl.) ; 'a. from food' उपवस् 1 P. **-Abstinence,** *s.* निवृत्ति *f.* 2 उपवासः, अल्पाहारः, आहारनियमः 3 संयमनं, जितेंद्रियत्वं **-Abstinent,** *a.* उपवासिन्. 2 जितेंद्रिय, संयतात्मन् ; वशिन्.

Abstemious, *a.* मिताहार, अल्पाहारिन्, अल्पाशन, मितभुज्. **-ness,** *s.* मिताहारः, मितभोजनं, अल्पाहारः.

Abstersion, *s.* शुद्धीकरणं.

Abstract, *v. t.* संक्षिप् 6 P, संहृ 1 P. 2 आदा 3 A, अप-अव-कृष् 1 P, अपहृ 1 P. **-s.** सारः, संग्रहः, संक्षेपः. **-a.** विभिन्न ; केवल ; अमूर्त. 2 आन्वीक्षिक (की *f.*), निगूढ. **-edly, -ly,** *adv.* विविक्तं. 2 केवलं, मात्रं. **-ion,** *s.* समाधिः, प्रणिधानं, ध्यानैकाग्रता. 2 अपहरणं, आदानं. 3 विभेदः, पृथक्करणं.

Abstruse, *a.* गूढ, प्रच्छन्न. 2 निगूढ, दुर्ज्ञेय गूढार्थ, असुबोध, दुर्बोध, गहन.

Absurd, *a.* अनर्थक, अयुक्त, न्यायविरुद्ध, अनुपपन्न **-ness, -ity,** *s.* आनर्थक्यं, अनुपपत्ति *f.*, असंगति *f.* ; sometimes ex. by शशविषाणं, गगनपुष्पं &c. **-ly,** *adv.* अविचारेण, अनुपपन्नं ; 'do not talk so a.' कृतमेतादृशेन असंगतेन-अनर्थकेन-प्रलापेन.

Abuse, *v. t.* वृथा-कुप्रयुज् -अन्यायतः उपयुज् 7 A, 10 or व्यय् 1 P. 2 अधि-आ-क्रुश् 10, भर्त्स् 10 A, आ-अधि-क्षिप् 6 P, अभिशंस् 1 P, अपवद् 1 U, अभिशप् 1 U, अपभाष् 1 A. **-s.** आक्रोशः, अपवादः, उपालंभः, अपभाषणं, निंदा, अधिक्षेपः, वाक्पारुष्यं, परुषोक्ति *f.* 2 कुप्रयोगः, अपव्ययः, अन्यायोपयोगः. **-Abusive,** *a.* निंदक, आक्षेपक, निंदागर्भ ; 'a. word' निंदात्मकवचः, आक्षेपवचनं.

Abut, *v. i.* अवलंब् 1 A, आधा 3 U (Pass.).

Abysm, *s. See* **Abyss.**

Abyss, *s.* गभीरगर्तः, अगाधबिलं, अतलस्पर्शं खातं.

Academy, *s.* विद्यालयः-यं. 2 विद्वत्परिषद् *f.*

Accede, *v. i.* अनुमन् 4 A, अंगी-स्वी-कृ 8 U, अनुज्ञा 9 U. 2 सं-इ 2 P, संविश् 6 P, सं-अभि-गम् 1 P.

Accelerate, *v. t.* त्वर् c. (त्वरयति), आशु संपद् c. or प्रवृत् c.

Accent, *s.* स्वरः. 2 आघातः, उच्चारणविशेषः ; 'human a.s' मानुषी गिर् *f.* **-v. t.** सस्वरमुच्चर् c. **-ed,** *a.* स्वरित, उदात्त.

Accept, *v. t.* प्रतिग्रह् 9 P, आदा 3 A, प्रतिपद् 4 A, प्रति-इष् 6 P, स्वीकृ 8 U. **-able,** *a.* ग्रहणीय, आदेय. 2 रुचिर, मनोरम, प्रिय. **-ance,** *s.* प्रतिपत्ति *f.*, प्रतिग्रहः, आदानं, स्वीकारः. **-ation,** *s.* अर्थः; आशयः; 'usual s. of a word' शब्दस्य निरूढार्थः.

Access, *s.* प्रवेशः, उपसर्पणं, अभि-उप-गमः; 'wishing to gain a. to the king' राजानं द्रष्टुकामः. **-ible,** *a.* सुलभ, सुखोपसर्प्य, अभि-, गम्य, सुगम, उपसर्पणीय; अवसरोपसर्पणीया राजानः (S. 6.), सुलभदर्शन; 'nothing is in a. to desires' मनोरथानामगतिर्न विद्यते (K. v. 64). **-ion,** *s.* योगः, उपगमनं, मिलनं. 2 (to power) राज्यप्राप्ति *f.*, राज्यप्राप्ति *f.*, सिंहासनारोहणं. 3 आगमः, वृद्धि *f.*, उपचयः. **-ary, -ory,** *s.* सहकारिन् *m.*, प्रवर्तकः, पापसहायः. **-a.** अधिक; सहित, संयुक्त.

Accident, *s.* समापत्ति *f.*, दैवयोगः-गति *f.*, दैवघटनं, यदृच्छा ; 'seen by a.' समापत्तिदृष्ट. यदृच्छा-दृष्ट. 2 आपद्-विपद् *f.*; अत्याहितं उपप्लवः. 3 अप्रकृति *f.*, असहजो गुणः, विकृति *f.*, 'life is but an a.' विकृतिर्जीवितमुच्यते (R. VIII. 87) ; 'by a.' अकस्मात्, दैवेन, दैवात्, दैवगत्या. **-al,** *a.* यादृच्छिक आकस्मिक (की *f.*), काकतालीय, दैवायत्त. 2 अप्रकृत, असमवायिन्, असहज, आहार्य. **-ally** *adv.* दैवात्, दैवयोगेन, यदृच्छया, विधि-दैव-वशात्, समापत्त्या, अकस्मात्.

Acclamation, *s.* धन्यवादः, प्रशंसाघोषः, जयशब्दः. 2 निःस्वनः, प्रणादः, उच्चैर्घोषः.

Acclivity, *s.* उन्नतिः.

Accommodate, *v. t.* युज् 10, *See* **Adapt**; 'a. oneself to the will of' चित्तमनुवृत् 1 A (स्वामिनो भावं भृत्योऽनुवर्तेत). 2 वस्तुविनियोगेन उपकृ 8 U, उपकरणानि उपनी c. 3 संधा 3 U. प्रशम् c., (dispute &c.). **-ion,** *s.* संधीकरणं, संधानं. 2 उपकरणानुयोगकल्पनं &c.

Accompany, *v. t.* अनु-इ 2 P, अनुया 2 P, परिवृ 5 U or c.; संयुज् 10; सह चर् or व्रज् 1 P, सं-इ, अनुव्रज् 1 P, सहचरो भू 1 P. **-ed,** *a.* सहित, अनुगत, समेत, परिवृत, परिवार, in comp. by Bah. comp. with स or word indicating 'companionship'; वसंतसहायः-सवसंतः-वसंतद्वितीयः कामः 'Cupid a. by Spring.'

Accomplice, *s.* अनुबंधिन्; *See* **Accessory**.

Accomplish, *v. t.* साध् 5 P or c., सिध् c. (साधयति); पूर् 10; समाप् c., अनुष्ठा 1 P, संपद् c., निर्वृत् c. **-ed,** *a.* सिद्ध, सं-,पूर्ण, संपन्न. 2 विशारद, निपुण, गुणवत्, कृतिन्. **-ment,** *s.* सिद्धि-समाप्ति *f.*, निर्वृत्ति *f.*, निष्पत्ति *f.* 2 कृतार्थता, कृतकृत्यता. 3 गुणित्वं, निपुणता, वैचक्षण्यं, गुणः.

Accord, *v. i.* संवद् 1 P, संयुज् pass. 2 एकचित्तीभू 1 P, एकमतीभू. **-v. t.** *See* Give. **-s.** संमतिः *f.*, स्वीकरणं. 2 ऐकमत्यं, एकचित्तता; 'with one a.' एकचित्तीभूय. 3 एकतालः (in music); 'of one's own a.' स्वेच्छया, स्वयं, स्वेच्छातः, कामतः. **-ance,** *s.* अनुसारः, सादृश्यं, अनुरोधः; 'in a. with his words' तद्वचनानुसारेण-रोधेन; oft. by the instr. or abl. of the noun itself; तद्विधाज्ञया, मदादेशात् &c. **-ing,** *prep.* यथा, अनुरूपं, अनु, in comp.; 'a. to seniority' अनुज्येष्ठं; 'a. to desire' यथेष्टं, यथाभिमतं; 'a. to one's power,' यथाशक्ति. **-ingly,** *adv.* इत्थं, तदनुरोधात्, तदनुसारेण, तथाच.

Accost, *v. t.* सं-अभि-आ भाष् 1 A, अभिधा 3 U, समामंत्र् 10 A, संबुध् c.

Accouchement, *s.* प्रसूति *f.* प्रसवः.

Accoucheur, *s.* प्रसव-सूति-वैद्यः.

Account, *s.* गणना, संख्यानं, विगणनं; 'balancing a. s' गणनां समीकृत्य. 2 मूल्यं, अर्घः. 3 गणना, मात्रा 'of what a. is a king' राजेति का मात्रा or गणना, 4 वृत्तांतः, कथा, कथनं, उपाख्यानं; 'to turn to a.' हितं साध् c., हितानुकूल *a.* कृ 8 U; 'take into a.' समीक्ष् 1 A, गण् 10, तेजसां हि न वयः समीक्ष्यते (R. xi. 1). 5 कारणं, हेतुः, निमित्तं; 'on a. of' ex. by the abl. or instr.; हेतोः, निमित्तेन अर्थे &c.; 'on this a.' अतः, अतःकारणात्; 'on no a.' कथमपि न; 'on one's a.' कृते (gen.); 'on all a. s' सर्वथा. **-v. t.** मन् 4 A. 2 गण् 10; 'a. for' कारणं निर्दिश्-वद् c. (with gen.). **-able,** *a.* निरूपणीय, प्रतिसंख्येय. 2 उत्तरदायित्वापन्न. **-ant,** *s.* गणकः, लेखकः, गणनाकृत् *m.*

Accoutre, *v. t.* संनह् 4 P or c. **-ment,** *s.* संनाहः, अलंकारः, भूषणं, प्रसाधनं, सज्जा.

Accredit, *v. t.* विश्वासपदं धा 3 U. 2 *See* 'Believe'. 3 *See* 'Ascribe'. **-ed,** *a.* मत, संमत, स्वीकृत.

Accrescent, *a.* *See* 'Increasing' under 'Increase'.

Accretion, *s.* *See* 'Increase, s'.

Accrue *v. i.* उत्पद्-जन् 4 A, प्राप् pass. 2 प्रतिवृत् 1 A, गम् 1 P; 'the fruit a. s to the agent' कर्तृगामि फलं.

Accubation, *s.* संवेशः, अधिशयनं.

Accumbent, *a.* संविष्ट, अधिशयान.

Accumulate, *v. t.* सं-प्र-चि 5 U, संवृध् 1 P, राशीकृ 8 U, एकत्र कृ. **-v. i.** उपचि pass, वृध् 1 A, राशीभू. 1 P. **-ion,** *s.* संचयः, राशीकरणं.

Accurate, *a.* यथार्थ, सूक्ष्म, सत्य, यथातथ, विशुद्ध, *See* Exact. **-ly,** *adv.* यथार्थेन-थं, सूक्ष्मतः, तत्त्वतः, सम्यक्, सत्यं. **-Accuracy,** *s.* याथार्थ्य, सत्यता, यथार्थता, सूक्ष्मता.

Accurse, *v. t.* *See* 'Curse' **-ed,** *a.* ex. by हतक, अपसद, at the end of nouns, or by दुष्ट pr.; 'the a. fate' दैवहतकं, दुष्टदैवं; 'a. man.' नरापसदः. 2 निंद्य, गर्हणीय; शापग्रस्त, अभिशप्त, आक्रुष्ट.

Accusative, *s.* द्वितीया विभक्ति *f.*

Accuse, *v. t.* अभियुज् 7 A, 10, अपवद् 1 A, अभिशंस् 1 P, अधिक्षिप् 6 P, दुष् c. नार्हसि कामापराधेन दूषयितुं (Ka. 235), घातकः अयं इति तमभियुयुजिरे 'they a. ed him of murder.' **-ation,** *s.* अभियोगः, अपवादः, अधिक्षेपः, अभिशंसनं, दूषणं. **-er,** *s.* अभियोक्तृ *m.*, अभियोगिन् *m.*

Accustom, *v. t.* अभ्यस् 4 P, अभ्यासं or व्यवहारं कृ 8 U; 'to be a. ed' अभ्यस्त-परिचित-अ. भू 1 P.

Ace, *s.* एकबिंदुः, 2 अणुः, लवः, 'within an a. of' आसन्न, *a.*

Acerb, *a.* तुवर, कटु, अम्ल. **-ate,** *v. t.* अम्लीकृ 8 U **-ity,** *s.* कटुता, अम्लता; 'a. of temper' स्वभावपरुषता, रूक्षता.

Acetic, *a.* *See* 'Acid, *a.*'

Acetify, *v. t.* अम्लीकृ 8 U.

Ache, *s.* वेदना, पीडा, व्यथा; 'head-a.' शिरोवेदना; 'I have a strong head-a.' बलवति शिरोवेदना मां बाधते; 'tooth-a.'

दुःखवेदना, -*v. i.* पीड् pass., व्यथ् 1 A. *See* **Pain.**

Achieve, *v. t.* समाप् c., संपद् c., निर्वृत् c., *See* **Accomplish. 2** प्राप् 5 P, लभ् 1 A. *See* **Get. -ment,** *s.* निष्पत्ति *f.*, साधनं. **2** पराक्रमः, विक्रमः, अद्भुतं कर्म-चेष्टितं, विख्यातचरितं.

Acicular, *a.* तीक्ष्णाग्र, सूच्यग्र.

Acid, *s.* अम्लः. -*a.* अम्ल, शुक्त. **-ify,** *v. t.* अम्लीकृ 8 U. **-ification,** *s.* अम्लीकरणं, **-imetre,** *s.* अम्लमापकः. **-ity,** *s.* अम्ल-शुक्त-ता or -त्वं. **-ulate,** *v. t.* अम्लीकृ 8 U. **-ulous,** *a.* ईषदम्ल.

Aciform, *See* ' Acicular. '

Acknowledge, *v. t.* अभ्युपगम् 1 P, अभ्युप-इ 2 P, प्रतिपद् 4 A, अंगीकृ 8 U, स्वीकृ; ग्रह् 9 P. **-ment,** *s.* स्वीकारः, अभ्युपगमः, अंगी-स्वी-कारः, प्रतिपत्ति *f.* **2** (receipt) अभ्युपगमलेखः-पत्रं, निस्तारलेखः.

Acme, *s.* परा काष्ठा-कोटि *f.*

Acoustic, *a.* श्रुतिविषयक, श्रवणसंबंधिन्. **-Acoustics,** *s.* ध्वनिविद्या-शास्त्रं.

Acquaint, *v. t.* बुध् c., ज्ञा c. (ज्ञापयति), निविद् c, (with dat.), गृहीतार्थ or परि-गृहीतार्थ *a.* कृ 8 U; 'the queen was made a. ed with your immodesty ' भवतोऽवि-नयमंतरेण परिगृहीतार्था कृता देवी (M. 4), **2** परिचयं कृ. अभ्यस् 4 P. **-ance,** *s.* परि-ज्ञानं; परिचयः, ज्ञानं. **2** मित्रं, परिचितः; ' old a. ' चिरंतनं मित्रं, चिरपरिचितः, **3** संसर्गः, संस्तवः, **-ed,** *a.* परिचित, अभ्यस्त; अभिज्ञ, अभ्यंतर; अनभ्यंतरे आवां मदनग-तस्य वृत्तांतस्य (S. 3).

Acquiesce, *v. i.* अनुमन् 4 A, अनुज्ञा U, संमतिं ग्रह् c. **-ence,** *s.* सं-अनु-मति *f.*

Acquire, *v. t.* अर्ज् 1 P, लभ् 1 A, समासद् c., अवाप् 5 P, प्रतिपद् 4 A, अश् 5 A, अधिगम् 1 P. *See* **Get. -ment, -Acquisition,** *s.* अर्जनं, प्राप्ति *f.*, लाभः, अधिगमः. **2** गुणः, ज्ञानं.

Acquit, *v. t.* (पापात्-दोषात्) मुच् c., वि-मुच् c., निस्तृ c., शुध् c.; ' he was a. ted ' स निर्दोषः कृतः, पापविमुक्तोऽमन्यत; 'a. oneself ' कर्म निर्वह् c., आचर् 1 P, ' they a. ted themselves well ' ते स्वकर्म साधु निरवाहयन् -आचरन्, **-al,** *s.* मुक्ति-शुद्धि *f.*, मोचनं. **-ance,** *s.* निस्तारः, ' a. of debt ' ऋणनिर्यातनं-परिशोधनं.

Acrid, Acrimonious, *a.* कटु, उग्र, तीक्ष्ण-अरुंतुद. **-Acrimony,** *s.* कटुता, तीक्ष्णता, **-Acritude,** *s.* कटुत्वं. **2** वाक्पारुष्यं.

Acrobat, *s.* कलापनः, सूत्रायणः.

Across, *prep.* पारं, तीरांतरं, in comp.; ' a. the ocean ' सागरपारं. **2** व्यत्यस्त *a.*; ' with legs a. ' व्यत्यस्तपाद् *a.*; ' to come a. ' लभ् 1 A, अधिगम् 1 P. *See* **Get.**

Act, *v. i.* वृत् 1 A आर्येऽस्मिन् विनयेन वर्तता (U. 6), व्यवहृ 1 P, आचर् 1 P, (with loc. of person); अपकाचरस्य कियद् तपस्विकन्यासु (S. 1) ' a. s rudely towards' &c. **2** चेष्ट् 1 A, विधा 3 U, कृ 8 U. **3** स्थानेऽधिकारं कृ. **4** फल् 1 P, गुणं आवह् 1 P; कार्यं कृ; ' fire a. s like water' अग्निर्जलायते; स कृष्णायते &c.; 'a. up to ' अनुवृत् 1 A; अनुरुध् 4 A, स्था 1 P, शासने तिष्ठ भर्तुः (V. 5). -*v. t.* नट् 10, निरूप् 10, अभिनी 1 P: प्रयुज् 10; oft. by denom.; 'a. ing the part of Lakshmi ' लक्ष्मीभूमिकायां वर्तमाना (V. 3); नृपायते ' a. s the king '; 'a. the part of a dear friend towards your rivals ' कुरु प्रियसखीवृत्तिं सपत्नीजने (S. 4.). -*s.* कर्मन् *n.*, कृति *f*, क्रिया, चरितं, चेष्टितं. **2** अंकः. **3** व्यवस्था, विधिः. **-ion,** *s.* क्रिया, व्यापारः, चेष्टितं &c.; प्रवृत्ति *f.*; कारणं. **2** अभियोगः, व्यवहारकार्यं, कार्यं, अर्थः. **3** संग्रामः, युद्धं, *See* **Fight. 4** अंगविक्षेपः, हस्ताद्यभिनयः, 'in a., thought and speech ' कर्मणा मनसा वाचा, मनोवाक्कायकर्मभिः. **-ionable,** *a.* अभियोज्य, व्यवहार्य. **-Active,** *a.* उद्योगिन्, कर्मोद्युक्त, अनलस, सोद्योग, सोत्साह, व्यवसायिन्. **2** क्षिप्रकारिन्, अतंद्र, क्षिप्रकर्मन् **3** व्यायामशील, व्यायामिन्. **4** उत्थानयोग्य, उत्थानयोग्यं वपुः (S. 2); 'a. voice ' कर्तृवाच्यम्. **-ity,** *s.* उद्योगिता, व्यवसायः, क्षिप्रकारिता. **2** उत्साहः. **3** उत्थानयोग्यता. **-ly,** *adv.* सोद्योगं, सोत्साहं. **-or,** *s.* कर्तृ *m.*; कारिन् *m.*; कारकः, in comp. **2** नटः, नर्तकः, कुशीलवः, अभिनेतृ *m*, शैलूषः. **-Actress,** *s.* नटी, नर्तकी. **-Actual,** *a.* वास्तविक (की *f.*), तथ्य, सत्य, वास्तव (वी *f.*), यथार्थ, परमार्थ. **-ly,** *adv.* साक्षात्, प्रत्यक्षं. **2** यथार्थतः, परमार्थतः, वस्तुतः, अर्थतः, वस्तुवृत्तेन; ' what a. took place ' यथावद् वृत्तं; oft. ex. by एव only.

Actuate, *v. t.* प्रेर् 10, प्रोत्सह्, c., प्रवृत् c., प्रणुद् 6 P; *See* **Prompt.**

Acumen, *s.* मतिसूक्ष्मता, विदग्धता.

Acute, *a.* नि-, शित, तीक्ष्ण; 'a.pain' दारुण-तीव्र-वेदना. **2** सूक्ष्ममति, विदग्ध. **-ly,** *adv.* तीव्रं, तीक्ष्णं. **-ness,** *s.* तीक्ष्णता, तेजस् *n.* **2** विदग्धता; 'a. of intellect' कुशाग्रबुद्धि *f.*

Adage, *s.* सूत्रं, वचनं, वाक्यं, आभाणकः.

Adamant, *s.* वज्रः-ज्रं. **2** हीरकः, मणिः, हीरं. **-ine,** *a.* वज्रमय (यी *f.*), वज्र in comp.

Adapt, *v. t.* युज् 10, संधा 3 U; ' a. your conduct to circumstances ' यथाकालं व्यवहर, कालानुवर्ती भव; ' has a. ed a

portion of it to the stage ' तस्यैकदेशः अभिनेयार्थः कृतः (U. 4). **-ation,** *s.* नियोजनं, संविधानं. **-ed,** *a.* युक्त, योग्य, पर्याप्त.

Add, *v. t.* संकल् 10 (कलयति), परिगण् 10, परिसंख्या 2 P, सं-समा-युज् 10; 'he a. ed his army to the general's ' सेनापतेः सेनया स्वबलं संयोजयामास; समाचि 5 U, संमिल् c. **2** अन्यच्च ब्रू 2 U, or कथ् 10 or अभिधा 3 U; ' a. to ' वृध् c., पुष् 4 P, तन् 8 U; मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति (S. 1) 'a. s to her lustre' ; there is this also to a. to my (grounds of) anger ' एतदपि मे द्वितीयं संतापकारणं (Mr. 5); 'this is another evil to a. to the first' गंडस्योपरि पिटिका संवृत्ता (S. 2), अयमपरो गंडस्योपरि विस्फोटः (Mu. 5). **-ition,** *s.* संमेलनं, संयोजनं, संयोगः. **2** परिगणनं, परिसंख्या, संकलनं. **3** (Something added) आधिक्यं; 'he is a valuable a. to our side' अस्मत्पक्षेऽयमनर्घ्यः सहायः संजातः. **-itional,** *a.* अपर, अधिक, अधिकतर.

Addict, *v. t.* (oneself) आ-नि-सेव् 1 A; भज् 1 U; आसंज् pass., आसक्त-निरत -*a.* भू 1 P, (loc). **-ed,** *a.* आसक्त, प्रसक्त, निरत, निविष्ट, परायण, in comp. **-edness, -ion,** *s.* आसक्ति-प्रसक्ति *f.*, निषेवणं, व्यसनं, निरति *f.*, परायणता.

Addle, *a.* असंपूर्ण, नष्ट, दुष्ट; ' a. headed-pated ' मूढ, नष्टधी, दुर्मति

Address, *v. t.* आमंत्र् 10 A; सं-अभि-आ-भाष् 1 A, अभिधा 3 U, संबुध् c., आलप् 1 P; 'a. ed his mind to Surya ' सूर्यं मनसाध्यायत्; 'a. me as is wont with you' (मां प्रति) यथाभ्यस्तमभिधीयताम् (U. 1.). **2** नाम ग्रह् 9 P, नामग्राहं वद् 1 P or आह्वे 1 P. **3** प्रहि 5 P, प्रेष् 10. **-s.** अभि-सं-भाषणं, संबोधनं &c. **2** वचनं, आलापः ; 'mode of a.' आमंत्रणपदं; संशयिते परिणये नैव समुदाचारः (S. 5). ' not the proper mode of a.'; 'of agreeable a. ' मधुरालाप, प्रियंवद. **3** पटुता, दक्षता, नैपुण्यं. **4** (Of a letter) बाह्यनामन् *n.*; अवृत्तबाह्यनामानं लेखं (Mu. 1) ' a letter without any a. upon it '; ' send the letter to my a. ' दत्त-लिखित-मद्बाह्यनाम (मामुद्दिश्य) पत्रं प्रेषय. **5** (Place of residence &c.) नामधामविशेषाः.

Adduce, *v. t.*(proof, witness &c.) निर्दिश् 6 P, उपन्यस् 4 P, उपक्षिप् 6 P, उपानी 1 P; 'a. ing proofs.' प्रमाणोपन्यासः.

Adept, *a.* निपुण, कुशल, प्रवीण, अभिज्ञ.

Adequate, *a.* पर्याप्त, समर्थ, क्षम, तुल्य योग्य, अनुरूप. **-ly,** *adv.* पर्याप्तं. **Adequacy,** *s.* क्षमता, सामर्थ्यं, &c.

Adhere, *v. i.* संसंज् pass., संलग्न् 1 P, संसक्त-अनुषक्त- *a.* भू, संलग् 1 P, (loc.); अनुबंध् 9 P. **2** अवलंब् 1 A, पाल् 10, रक्ष् 1 P; 'a. s to his promise' प्रतिज्ञां पालयति-रक्षति. **-ence,** *s.* आसक्ति *f.*, आसंगः, अनुषंगः, अवलंबनं. **-ent,** *s.* पक्षीयः, पक्ष्यः, सपक्षः. **2** अनुषंगिन् *m.*, सहायः, अनुगामिन् *m.* **-Adhesion,** *s.* संसक्ति *f.*, आसंगः, आसक्ति, *f.* अवलंबनं, संलग्नत्वं. **-Adhesive,** *a.* संलग्नशील.

Adieu, *adv.* स्वस्ति (dat). *s.* आमंत्रणं, आप्रच्छनं; 'to bid a.' आप्रच्छ् 6 A, आमंत्र् 10 A; आमंत्रयस्व सहचरं (S. 3).

Adjacent, *a.* आसन्न, समीप, समीपवर्तिन्, सन्निकृष्ट, सन्निहित, निकटवर्तिन्, निकट, पार्श्वस्थ.

Adjective, *s.* विशेषणं.

Adjoin, *v. t.* लग् 1 P, समीपि-निकटे-वृत् 1 A or स्था 1 P; *See* **Adjacent** above.

Adjourn, *v. t.* व्याक्षिप् 6 P, विलंब c.; व्यवहारं त्यज् 1 P.

Adjudge, *v. t.* दा c. (दापयति). **2** निर्णयं कृ 8 U, निर्णयं समाप् c.

Adjudicate, *v. t.* निर्णी 1 P. *See* above.

Adjunct, *a.* संयुक्त, सहित. **-s.** अनुबंधः.

Adjure, *v. t.* सशपथं समादिश् 6 P, शप् c. **-ation,** *s.* सशपथं समादेशः, शपथः.

Adjust, *v. t.* समीकृ 8 U, समा-प्रतिसमा-धा 3 U, समायुज् 10, व्यवस्था c. (स्थापयति); (accounts) एकीकृ, संमिल् c. **-ment,** *s.* समाधानं, समायोगः, एकीकरणं.

Adjutant, *s.* सहायः, सहकारिन् *m.*

Admeasure, *v. t.* *See* ' **Measure** '.

Administer, *v. t.* प्रशास् 2 P, निर्वह् c., निर्वृत् c.; 'a. justice' धर्म-न्याय-विवेचनं कृ, न्यायं प्रणी 1 P, or प्रवृत् c.; ' a. an oath ' शप् c. **2** दा 3 U, प्रतिपद् c. **-Administration,** *s.* शासनं, प्रवर्तनं, निर्वाहः; राज्यधुरा; 'during his a.' तस्मिन् राज्यं (प्रजाः) शासति. **2** धर्मविवेचनं. **3** प्रकृति *f.*, सचिवाः. **4** साचिव्यं, मंत्रित्वं. **-Administrative,** *a.* शासनदक्ष, कार्यनिर्वाहकुशल. **-Administrator,** *s.* शासितृ *m.*, राज्यधुरंधरः. **2** प्रवर्तकः, प्रणेतृ *m.*

Admiral, *s.* नौसाधनाध्यक्षः.

Admire, *v. t.* प्रशंस् 1 P, श्लाघ् 1 A, स्तु 2 U. **2** विस्मयेन दृश् 1 P. **-able,** *a.* श्लाघ्य, अद्भुत, प्रशंसनीय, अनुपम. **-ably,** *adv.* श्लाघ्यप्रकारेण, साधु, अद्भुतं. **-ation,** *s.* प्रशंसा, श्लाघा. **2** विस्मयः, आश्चर्यं. **-er,** *s.* प्रशंसकः, श्लाघिन् *m.*; ' a. of ladies ' कामिन् *m.*, कामुकः.

Admit, *v. t.* प्रविश् c., अभ्यंतरीकृ 8 U; 'should be a. ed to all confidential matters' सर्वविश्रंभेष्वभ्यंतरीकरणीय (Ka. 101). 2 अंगी-स्वी-कृ ,अभ्युपगम् 1 P, अभ्युपे 2 P; ग्रह् 9 P; 'a. of' ex. by adj. or noun denoting 'capability'; 'his remark a. s of no doubt' तस्य वचनं न संदेहास्पदं; 'her illness a s of no delay' तस्या विकारो विलंबाक्षमः. **-Admission,** *s.* प्रवेशनं, प्रवेशः. 2 अभ्युपगमः, अंगीकारः, प्रतिपत्ति *f.* **-Admissible,** *a.* उपादेय, स्वीकरणीय, ग्राह्य. **-Admittance,** *s.* प्रवेशः-मार्गः.

Admix, *v. t.* संमिश्र् 10, संयुज् 7 U, 10, संकृ 6 P. **-ture,** *s* मिश्रणं, संकरः.

Admonish, *v. t.* उपदिश् 6 P, अनुबुध् c., विज्ञा c. (ज्ञापयति), अनुशास् 2 P. 2 निर्भर्त्स् 10 A, उपालभ् 1A, *See* **Censure.** **-er,** *s.* उपदेशकः, अनुबोधकः. **-Admonition,** *s.* अनुबोधनं, उपदेशः, अनुशासनं, उपालंभः.

Ado, *s.* श्रमः, दीर्घायासः.

Adolescence, *s.* यौवनदशा, यौवनं. **-Adolescent,** *a.* युवन् (यूनी *f.*), प्राप्तयौवन.

Adopt, *v. t.* परिग्रह् 9 P, पुत्रीकृ 8 U. 2 ग्रह्, स्वी-अंगी-कृ, अनुवृत् 1 A. **-ed,** *a.* परिगृहीत, स्वी-अंगी-कृत; 'a. son' कृतकः पुत्रः, कृत्रिमः सुतः, दत्तकः; 'a. daughter' कृतिका दुहिता, अपत्यकृतिका. **-ion,** *s.* परिग्रहः, पुत्रीकरणं. 2 अंगी-स्वी-कारः, अनुवर्तनं.

Adore, *v. t.* आराध् c , नमस्यति (D), नमस्कृ 8 U, अर्च् 1 P, or c. पूज् 10, उपस्था 1 U, उपास् 2 A. **-ation,** *s.* पूजा, अर्चनं, नमस्कारः. **-er,** *s.* पूजकः, उपासकः, आराधकः, भक्तः, अर्चकः.

Adorn, *v. t.* वि-भूष् 10, अलंकृ 8 U, परिष्कृ, संस्कृ, मंड् 10 प्रसाध् c., शुभ् c. **-ing,** *s.* अलंकारः, भूषणं, प्रसाधनं, मंडनं.

Adrift, *adv.* इतस्ततः प्लवमान *a.* 2 अशरण-अनाथ-निरालंब. *a.*

Adroit, *a.* निपुण, दक्ष, धूर्त, चतुर. **-ly,** *adv.* सनैपुण्यं, चातुर्यं &c. **-ness,** *s.* नैपुण्यं, दक्षता, &c.

Adry, *a. See* 'Thirsty'.

Adulate, *v. t* श्लाघ् 1 A, स्तु 2 U, अनुनी 1 P. **-ion,** *s.* चाटूक्ति *f,* अतिप्रशंसा, श्लाघा, स्तुतिपूर्वकः अनुनयः, स्तवोक्ति *f.*, अतिस्तुति *f.* **-ory.** *a.* चाटूक्तिपूर्ण, प्रशंसागर्भ, अतिप्रशंसात्मक.

Adult, *s.* प्रौढः, प्राप्तयौवनः, प्राप्तव्यवहारवयस्कः, युवन् *m.*

Adulterate, *v. t.* अपद्रव्येण संमिश्र् 10, अशुद्धी कृ 8 U. **-ion,** *s.* दूषणं, मिश्रणं.

Adultery, *s.* व्यभिचारः, पारदार्यं, परदारगमनं; (of a woman) परपुरुषसंगति *f.*, पतिलंघनं. **-Adulterer,** *s.* परदारगामिन् *m.* पारदारिकः, लुब्धकः, विटः, जारः. **-Adulteress,** *s.* व्यभिचारिणी, जारिणी, पुंश्चली, परपुरुषसंगता, बंधकी. **-Adulterine,** *a* जारजः.

Adumbrate, *v. t* पांडुलेख्यं-प्रतिच्छायां-चित्रारंभं-कृ 8 U. **-tion,** *s.* प्रतिच्छाया, प्रतिबिंबं. 2 पांडुलेख्यकरणं.

Adust, *a.* दग्ध, भस्मी-भूत or कृत.

Advance, *v. i.* प्र-उत्-चल् 1 P, प्र-अभि-या 2 P, अभिमुखं या, or -गम् व्रज् 1 P, प्रसृ, प्रस्था 1 A; शत्रोरभिमुखं याति 'a. s against the enemy.' 2 वृध् 1 A, प्र-उत्-चि pass. उन्नति-उत्कर्ष-या; 'a. ed some steps to receive' सादरमभिमुखपदानि चचाल (Ka. 95); 'a. ed in age' परिणतवयस्, वयोवृद्ध, प्रवयस्; 'a. ed in knowledge' ज्ञानवृद्ध. **-***v. t.* उन्नम् c., पुरस्कृ 8 U, अग्रे नी 1P. 2 वृध् c., परिपुष् 4 P 3 उपक्षिप् 6 P, उपन्यस् 4 P, पुरो निधा 3 U. 4 प्राक् दा 3 U. **-***s.* उच्चलनं, प्रगमनं, प्रयाणं. 2 उन्नति *f.*, क्रमशो वृद्धि *f.*, उत्कर्षः, वर्धनं; 'price of a book in a.' पुस्तकप्रकाशनात्पूर्वं दत्ते मूल्ये. **-ment,** *s.* उत्कर्षः, उन्नति *f.*, अभ्युदयः, वृद्धि *f.*, आगमः, उपचयः, 'a. in knowledge' विद्यागमः; 'a. of learning' ज्ञानोत्कर्षः.

Advantage, *s.* लाभः, हितं, गुणः, फलं, अर्थः. 2 अवसरः, अवकाशः. 3 आधिक्यं, उत्कर्षः; 'taking a. of my weak point' मम छिद्रेण लब्धावकाशः; 'show or set off to a.' लक्ष्मीं-शोभां-तन् 8 U, *See* **Add.** 'They had an a. over their enemy in bravery' शौर्ये ते शत्रुभ्योऽभ्यधिकाः. **-***v. t.* उपकृ 8 U, अनुग्रह् 9 P, लाभाय भू. **-ous,** *a.* फलद, हितावह, लाभकर, हितकर (री *f.*). **-ously,** *adv.* सफलं, सलाभं. 2 सावकाशं.

Advent, *s.* आगमनं, प्रवृत्ति *f.*; 'a. of spring' वसंतसमयावतारः, मधुप्रवृत्ति *f.* **-itious,** *a.* बाह्य, औपाधिक-आगंतुक (की *f.*), आहार्य.

Adventure, *s.* साहसं, अद्भुतं कर्म. 2 दैवाधीनं कर्मचेष्टितं. 3 वृत्तांतः, चरितं, चेष्टा, चेष्टितं, क्रिया. **-***v. i.* दैवाधीनं कर्म कृ 8 U. 2 साहसेन व्यवसो 4 P, or प्रयत् 1 A. **-er,** *s.* साहसिकः, साहसव्यवसायिन् *m.* **-ous,** *a.* साहसिक (की *f.*), प्रगल्भ, निर्भय. 2 संदिग्ध, दैवायत्त.

Adverb, *s.* क्रियाविशेषणं, अव्ययं.

Adverse, *a.* प्रतिकूल, विपक्ष, वैरिन्, विपरीत, वाम, विरुद्ध, पराङ्मुख (खी *f.*). **-ary,** *s.* शत्रुः, अरिः. *See* **Enemy. -ative,** *a* विरोध-दर्शक-द्योतक. **-ity,** *s.* विपद् *f.*

[' आपद् *f*, विपत्ति *f*., आपत्काल:, व्यसनं,दुर्दशा.
Advert (to), *v. i.* उद्वाह् 1 P, अनुलक्ष् 10, अधिकृत्य-उद्दिश्य-वद् 1 P or वच् 2 P. **2** अव-सं-ईक्ष् 1 A, मन: समाधा 3 U, अवधा, अवधानं दा 3 U. **-ence**, *s.* अवधानं, अवहितता, मनोयोग:, अवेक्षा.
Advertise, *v. t.* विज्ञा c. (ज्ञापयति), निविद् c., प्रकाश् c., घुष् c., वि-उद्-घुष् 10. **-er**, *s.* प्रकाशक:, ज्ञापक:.**-ment**, *s.* विज्ञापना, घोषणा.
Advise, *v. t.* उपदिश् 6 P, अनुशास् 2 P. **2** बुध् c., निविद् c., ज्ञा c. (ज्ञापयति). **-**v. *i.* विचर् c., आलोच् 10. **-able**, *a.* उचित, योग्य, युक्त. **2** उपदेष्टव्य. **-edly**, *adv.* सुविचारतः, ज्ञानतः, बोधपूर्वं. **2** सावधानं, अवधानेन. **-er**, *s.* उपदेशक:, उपदेष्टृ *m*. **2** सचिव:, अमात्य:, मंत्रिन् *m*.**-Advice**, *s.* उपदेश:, अनुशासनं, बोधनं. **2** समाचार:, वार्ता.
Advocate, *v. t.* परार्थं वद् 1 P, पक्षं समर्थ् 10 or रक्ष् 1 P. **-**s. परार्थे वक्तृ *m*, पक्षसमर्थक:, वक्तृ *m*. **2** आश्रय:, रक्षक:, प्रतिपालक:.
Adze, *s.* कुठारिका, तक्षणी.
Aerial, *a. See* under **Air**.
Aeroplane, *s.* आकाशयानं, विमानं.
Aery, *a.* आध्यात्मिक. **2** अमूर्त. **3** मनःसृष्ट-कल्पित.
Afar, *adv.* दूरात्, आरात् ; दूरे-तः ; ' a. off ' दूरस्थ *a*.
Affable, *a.* सुजन, सुशील. **2** मधुरालाप, प्रियवादिन्. **-Affability**, *s.* मधुरालापता, सुशीलत्वं, सौजन्यं, प्रश्रय:. **-Affably**, *adv.* चाटूक्त्या, मृदुवचनेन, सुजनवत्, सप्रश्रयं.
Affair, *s* कार्यं, व्यापार:, कर्मन् *n*., अर्थ:.
Affect, *v. t.* (To act upon) अभिभू 1 P, आकुलीकृ 8 U, उपहन् 2 P, विकृ, उपसृज् 6 P, सस्कृ ; क्लेशलेशैरभिन्नं (S. 2) 'not a. ed by the slightest fatigue '; 'a. ed by a devil ' वेतालोपहत ; ' a. ed with many diseases' अनेकव्याध्युपसृष्ट ; ' our position is not in the least a. ed (it does not a. us in the least) ' न नः किंचिच्छिद्यते (S. B. 345). **2** (Pretend) Ex. by छद्म-छलं कृ, मिथ्या in comp., by कृतक-कृत्रिम-*a*. कृ ; ' a. ing a quarrel or anger ' कृतककलहं-कोपं-कृत्वा. **3** आकुलीकृ, आर्द्रीकृ, द्रु c.; अवकाशं-पदं-ग्रह् 9 P; ' my words a. ed his heart ' मम वचसा तस्य हृदयं द्रवीभूतं, मम वचस्तस्य हृदये पदं चक्रे लेभे. **4** मन् 4 A ; ' he a. s learning' पंडितंमन्योसौ. **-ation**, *s.* अहंकार:, आरोप:, मिथ्याचारित्वं. **2** छद्मन् *n. See* **Pretext**. **3** विलास:, अभिनय:, हाव:. **-ed**, *a.* आकुल, अभिभूत,उपहत, विकृत. **2** मिथ्या in comp.; कृतक, कृत्रिम ; ' by an a. courage ' मिथ्यामतायमात्मन्यारोप्य. **3** अहंकारिन्, मानिन्, सदर्प. **-edly**, *adv*. साहंकारं, साटोपं. **-ing**, *a.* करुणं, मर्मभेदिन्. **-ingly**, *adv.* करुणं. **-ion**, *s.* प्रेमन् *m. n.*, अनुराग:, स्नेह:, प्रणय:, प्रीति *f.*, वात्सल्यं, (with loc.). **2** धर्म:,संस्कार:, विकार:, अनुभाव:, वृत्ति *f*., भाव:, विक्रिया, राग:. **-ionate**, *a.* स्निग्ध, स्नेहशील, प्रणयिन्, सप्रणय, सानुराग, वत्सल. **-ionately**, *adv.* सप्रेमं, सस्नेहं, स्निग्धं, सानुरागं.
Affiance, *v. t.* प्रतिश्रु 5 P, वाचा दा 3 U. **-s.**, वाग्दानं. **2** विश्वास:, श्रद्धा.
Affidavit, *s.* शपथपत्रं, सशपथं लिखितो लेख:.
Affiliate, *v. t.* सांश्लिष् c., संयुज् 10.
Affinity, *s.* संबंध:, संपर्क:, योग:. **2** बंधुता, त्वं, सादृश्यं, साम्यं.
Affirm, *v. t.* प्रतिज्ञा 9 A,वद् 1 P, वच् 2 P उपक्षिप् 6 P, उपन्यस् 4 P. **2** सनिश्चयं वद्, तथेति दृढं ब्रू 2 U. **3** दृढीकृ 8 U, निश्चित *a*. कृ, प्रमाणीकृ. **-ation**, *s.* उक्ति *f*. दृढवचनं, प्रमाणीकरणं, सनिश्चयं वचनं **2** प्रतिज्ञा,पक्ष:. **-ative**, *a.* स्वीकार or अंगीकारद्योतक or सूचक ; ' two negatives make one a.' द्वौ नञौ प्रकृतार्थं गमयत:. **2**; पक्षानुकूल
Affix, *s.* आगम:. **-**v. *t.* अनुबंध् 9 P, सं-आ-युज् 7 U, 10.
Afflict, *v. t.* क्लिश् 9 P, दु 5 P, परि-सं-तप् c., व्यथ् c. (व्यथयति), पीड् 10, बाध् 1 A, आयस् c. **-ed** *a.* आर्त, दु:खित, अभिभूत, पीडित, आतुर. 'to be a. for' तप् 4 P. ... *a.* भू 1 P. **-ion**, *s.* क्लेश:, बाधा, पीडा, कष्टं, व्यथा, दु:खं. **-ing**, **-ive**, *a.* क्लेशावह, व्यथाकर (री *f*.).
Affluence, *s.* समृद्धि *f*., सधनता,धनबाहुल्यं. **-Affluent**, *a.* समृद्ध, धनाढ्य, बहु-महाधन; 'a. circumstances' सधनता, सुस्थिति *f*. **2** एकस्थानं प्रति प्रवाहक. **-Afflux**, *s.* एकस्थाने प्रवाह:.
Afford, *v. t.* दा 3 U. **2** (To be able) शक् 5 P, समर्थ-क्षम-*a*. भू 1 P.
Affray, *s.* कलह:, द्वंद्वं, युद्धं.
Affright, *v. t.* संत्रस् c., भी c. (भाययते, भीषयते), उद्विज् c. **-s.** भयं, सं-,त्रास:-साध्वसं.
Affront, *s.* अवज्ञा, निकृति *f*., अपमान:, तिरस्कार:, मानभंग:. **-** *v. t.* (संमुखं-मर्यक्षं) अवज्ञा 9 U, अवमन् 4 A, अधिक्षिप् 6 P, तिरस्कृ 8 U.
Affusion, *s.* आसेक:.
Afire, **Aflame**, *a.* ज्वलमान.

Afloat, *a.* प्लवमान, 'a rumour is a.' वार्ता प्रचलिता.

Afoot, *adv.* पद्भ्याम् ; 'set a.' प्रारभ् 1 A. *See* **Begin;** 'the army is a.' प्रचलितं सैन्यं, 'going a.' पादग, पादचारिन्.

Afore, *adv.* अग्रे, पुरः, संमुखं. **2** पूर्वं, पुरा, गतकाले; 'a. said,' पूर्वोक्त, प्रागुक्त. 'a. thought.' *s.* पूर्व-प्राक्-संकल्पित; 'a.times,' *adv.* पुरा.

Afraid, *a.* भीत, भयान्वित, शंकान्वित; 'to be a.' त्रस् 1, 4 P, भी 3 P, (with abl.). **2** आ-शंक् 1 A, मन् 4 A.

Afresh, *adv.* पुनरपि, अभिनवं.

After, *prep.* अनु pr. to roots, पश्चात्; 'to go a.' अनुगम्, अनुसृ, 1 P. **2** (of time) परं, अनंतरं, ऊर्ध्वं, (with abl.): 'a. that' तस्मात्परं, ततऊर्ध्वं; 'a. one another' आनुपूर्व्येण, अनुपूर्वशः. 'a. 10 years' दशवर्षे व्यतीते, 'a. eating' भोजनानंतरं; पश्चात् (gen.), अनु in comp.; 'a. a few days' दिनेषु गच्छत्सु; by gerund, or पूर्वकं in comp.; अनामयप्रश्नपूर्वकं (S. 5); 'he waters tree a. tree' वृक्षं वृक्षं सिंचति; 'in a. time' आगामिकाले, उत्तरकाले. **3** अनुकरणेन-सादृश्येन, अनुरूपं; 'you write a. his hand' लिखने तस्यानुकरोषि; 'he is called a. his grandfather' स पितामहनाम्नाऽभिधीयते-आहूयते; *See* **Name.** In comp. e. g. 'a. ages,' ex. by उत्तर; 'a.-ages' उत्तरकालः; पुत्रपौत्राः; 'a. all' अंते, शेषे; 'a. birth,' *s.* जरायु *n.* 'a.-crop' सस्यस्य द्वितीयसंग्रहः; 'a. glow, *s.* सायं-संध्या-प्रकाशः. 'a.-inquiry,' उत्तरजिज्ञासा; 'a.-life' आयुःशेषः, उत्तरवयस् *n.*; 'a. noon' *s.* अपराह्णः, पराह्णः, विकालः; (*a.*) अपराह्णतन (नी *f.*), वैकालिक (की *f.*); 'a. pains,' प्रसवोत्तरवेदना. 'a. thought,' उत्तरचिंता. अनुबोधः. 'a. wards' पश्चात्, अनंतरं, ततः परं, परं.

Again, *adv.* पुनः, भूयः; 'a. and a.' भूयो भूयः, वारंवारं; 'as much a.' द्विगुण *a.* **2** अपरं च, अन्यच्च, अपि च. **3** (With verbs) by प्रति pr.

Against, *prep.* प्रति-अभि pr. to nouns; प्रतिवातं 'a. the wind' &c. **2** अभिमुखं, प्रतिमुखं, संमुखं, in comp. or with gen. **3** विरुद्धं, प्रतिकूलं, or by अतिक्रम्य; 'a. my order' मम शासनस्य विरुद्धं, शासनमतिक्रम्य-उल्लंघ्य; 'assist him a. his brother' भ्रातरि बद्धवैरस्य तस्य साहाय्यं कुरु. **4** अर्थं, अर्थे; आपदर्थे धनं रक्षेत् 'should lay by wealth a. (as a provision for) calamities.'

Agape, *a.* जृंभमाण, 'with eyes a. with astonishment' विस्मयोत्फुल्ललोचन.

Agastric, *a.* जठरशून्य.

Age, *s.* युगं, कालः, समयः. **2** वयस् *n.*; 'a. of the world' कल्पः; 'old a.' वृद्धत्वं, वार्धक्यं, वृद्धभावः, परिणतं वयस् *n.* 'come of a.' प्राप्तव्यवहार; 'of the same a.' समकालीन, समानवयस्क; 'of age' ex. by वर्षीय *a.* वर्षात्मक *a.*; '5 years of a.' पंचवर्षीय-वर्षात्मक; 'about 8 years of a.' अष्टवर्षदेशीय; 'a. of majority' यौवनदशा, यौवनावस्था; व्यवहारज्ञताधिकवयस् *n.* 'he reached the 16th year of his a.' षोडशवर्षवयोवस्थामनुप्राप्तः. **-ed,** *a.* वृद्ध, जीर्ण, पुराण.

Agenda, *s.* कार्यक्रमपत्रं.

Agent, *s.* प्रतिहस्तः, प्रतिनिधिः. **2** (in grammar) कर्तृ *m.*; कारकः, कारः in comp. **3** हेतुः, कारणं, साधनं, शक्ति *f.* **-Agency,** *s.* कर्तृत्वं, निर्मातृत्वं; 'the action was done through his a.' तत्कर्तृका क्रिया, तस्य साहाय्येन संपादिता क्रिया. **2** कारणं. **3** नियोगिपदं, नियोज्यत्वं.

Agglomerate, *v. t.* संचि 5 U, एकत्र-राशीकृ 8 U.

Agglutinate, *v. t.* संयुज् 10, संश्लिष् *c.* संलग्न *a.* कृ 8 U, संसंज् *c.*

Aggrandize, *v. t.* वि-सं-प्र-वृध् *c.*, आप्यै *c.*, एध् *c.*, स्फाय् *c.* (स्फावयति), उत्कृष् 1 P, उपचि 5 U. **-ment,** *s.* विवृद्धि *f.*, उन्नति *f.*, अभ्युदयः, उत्कर्षः, उपचयः, उदयः.

Aggravate, *v. t.* वृध् *c.*, उपचि 5 U, प्रवृद्धिं नी 1 P. **2** प्रकुप् *c.*, संक्षुभ् *c.*, उद्दीप् *c.* **-ion,** *s.* वृद्धि *f.*, उपचयः. **2** प्रकोपनं-णं, उद्दीपनं.

Aggregate, *s.* संग्रहः, समाहारः, राशिः, समूहः, समुदायः. **—*v. t.*** संग्रह् 9 P, राशीकृ 8 U, संचि 5 U, एकत्र कृ. **-ed,** *a.* एकीकृत, समुच्चित, संचित, समाहृत. **-ion,** *s.* संग्रहणं, राशीकरणं. **2** समूहः, *See* (*s*) above.

Aggress, *v. i.* (प्रथमं) आक्रम् 1 U, 4 P, लंघ् 1 A, 10, हिंसारंभं कृ 8 U. **-ion,** *s.* आ-अति-क्रमः, लंघनं. **2** प्रथमापकारः, हिंसारंभः. **-ive,** *a.* प्रथमापकारिन्, 'a. step' हिंसारंभः, प्रथमाक्रमः. **-or,** *s.* प्रथमापकारकः, आक्रामकः.

Aggrieve, *v. t.* अर्द् 1 P or *c.*, दुःखाकुलीकृ 8 U, *See* **Afflict.**

Aghast, *a.* ससाध्वस, भयाभिभूत. **2** विस्मयाकुल, आश्चर्यचकित.

Agile, *a.* लघु, चपल, लघुशरीर.

Agitate, *v. t.* सं-वि-प्र-क्षुभ् *c.*, आकुलीकृ 8 U, उद्विज् *c.*; धू 5, 9 U, मंथ् 9 P, विलुड् *c.* (water). **2** **Discuss,** q. v. **-ed,** *a.*

क्षुब्ध, विह्वल, आकुल, विक्लव, पारिप्लव. 2 प्रमथित, विलोडित; 'to be a.', क्षुभ् 4, 9 P, 1 A, विह्वल &c. भू. -ion, s. संक्षोभः, उद्वेगः, उपप्लवः, आकुलत्वं. 2 विलोडनं. 3 विचारणा, वादानुवादः. -or, s. क्षोभकः.

Aglow, *a.* अग्नितप्त.

Agnate, *a.* संबंधिन्, संबद्ध.

Agnostic, *s.* अनीश्वर-निरीश्वर-वादिन् *m.*

Ago, *adv.* पूर्वं, प्राक्, (with abl.); 'long a.' पुरा; 'not long a.' नातिचिरात्प्राक्, अनतिपूर्वं.

Agony, *s.* व्यथा, यातना, वेदना, संतापः; 'in the a. es of death' मृत्युवेदनाभिभूत; 'sharp a.' तीव्रयातना-वेदना &c. -ize, *v. i.* व्यथ् 1 A. -*v. t.* Afflict, q. v.

Agrarian, *a.* भूमिविषयक, क्षेत्रसंबंधिन्.

Agree, *v. i.* संमन् 4 A, तथा-एवं-मन्; 'I don't a. with you' नैवमहं मन्ये. 2 एकचित्तीभू, एकमतं *a.* भू; 'birds in their nests a.' स्नेहभावेनैकत्र वसंति; 'they all a. on this point' अस्मिन्विषये सर्वेषां तेषामैकमत्यम्. 3 ग्रह् 9 P, स्वीकृ 8 U, अनुमन् 4 A, अनुज्ञा 9 U. 4 संकॢप् c., समयं-संविदं-कृ, प्रतिपद् 4 A, अभ्युप-इ 2 P or गम् 1 P, प्रतिश्रु 5 P. 5 आरोग्याय कॢप् 1 A, हिताय भू, हितमावह् 1 P; '(living in) Bombay does not a. with my health' मुंबापुरनिवासो ममारोग्याय न कल्पते. 6 Resemble, q. v. -able, *a.* रम्य, सुख in comp. सुखस्पर्शा शिलाविशेषस्य (M. 4); मनोज्ञ, प्रिय, सुखद, अभिमत, सुभग. 2 अनुरूप, योग्य, तुल्य, सदृश (शी *f.*). -ably, *adv.* यथासुखं. 2 अनुरूपं, अनुसारतः; 'a. to one's nature' स्वभावानुरूपं. -ment, *s.* समयः, संविद् *f.* 2 ऐकमत्यं, संमति *f.*, ऐकमत्यं. 3 सादृश्यं, संवादः. 4 अभ्युपगमः, स्वीकारः, प्रतिपत्ति *f.*

Agrestic, *a.* असभ्य, ग्राम्य, क्षेत्रिक.

Agriculture, *s.* कृषि *f.*, कर्षणं; 'science of a.' कृषिकर्मविद्या. -Agriculturist, *s.* कृषीवलः, कर्षकः, कृषिजीविन् *m.*, क्षेत्रिन् *m.* 2 वैश्यः, विश् *m.*

Agronomial, *a.* क्षेत्रकर्मविषयक, कृषिकर्मसंबंधिन्.

Aground, *adv.* तटस्थ *a.*, उत्तीर्णं, सैकतस्थं.

Ague, *s.* कंप-शीत-ज्वरः, विषमः; 'tertian a.' त्र्याहिकविषमः; 'quartan a.' चातुर्थिकविषमः.

Aguerried, *a.* युद्धपरिचित, युद्धाभ्यस्त.

Ah, *interj.* आः, हेत, हा, अहो, अहह.

Ahead, *adv.* अग्रे, पुरतः, पुरः.

Aheap, *adv.* संकलितं.

Aid, *v. t.* उपकृ 8 U, साहाय्यं कृ (with gen.). -*s.* साहाय्यं, उपकारः. 2 सहायः, उपकारकः. -less, *a.* असहाय. *See* **Help.**

Aid-de-camp, *s.* आसन्नसहायः. 2 सेनापतिसहायः.

Ail, *v. t.* पीड् 10; दु 5 P, तप् c.; 'what a. s thee' किं त्वां व्यथयति or का ते पीडा. -ing, *a.*, पीडित, क्षुद्ररोगपीडित. -ment, *s.* पीडा, आतंकः. 2 क्षुद्ररोगः, व्याधिः

Aim, *v. t.* लक्षीकृ 8 U, उद्दिश् 6 P, संधा 3 U; 'well a. ed arrow' साधुकृतसंधानः शरः (S. I.). 2 आप् desid. (ईप्सति), आकांक्ष् 1 P, लभ् desid. (लिप्सते); 'a. ed at the crown' राजपदं लिप्समानः &c. 3 लक्ष्यं प्रति क्षिप् 6 P or अस् 4 P. -s. लक्ष्यं-क्षं, शरव्यं. 2 संधानं; 'taking a.' शरसंधानं कुर्वन्. 3 अभिप्रायः, आशयः, वांछा, कांक्षा, हेतुः, चिकीर्षितं; 'friend, where are you going without any definite a.' हला कमनिर्दिष्टकारणं गम्यते (V. 2).

Air, *s.* व्योमन् *n.*, आकाशः-शं, नभस् *n.*, विहायस् *n.*; 'to take the a.' वातमासेव् 1 A; 'take a.' प्रकाशतां गम् 1 P. 2 वायुः, वातः, समीरणः. 3 तालः, रागः, मूर्छना. 4 रूपं, आकारः, मुद्रा; 'with a dignified a.' सगौरवाकारेण; 'a. of conceit' अवलेपमुद्रा; 'with the a. of one who is offended' निकृतमिवात्मानं संदर्श्य. 5 गति *f.*, विधि *m.*, प्रकारः, रूपं; 'through a.' विहायसा, नभोवर्त्मना; 'to build castles in the a.' गगनकुसुमानि चि 5 U; 'a. balloon' आकाशयानं, व्योमयानं; 'a. bladder' वायुकोषः; 'a. hole' वातायनं, गवाक्षः, जालं; 'a. born,' 'aerial,' आकाशज; आकाशस्थ, नभःस्थ. -y, *a.* वायव (वी *f.*), वायुमय (यी *f.*). 2 सुवात, प्रवात; 'a. place' प्रवातं; प्रवातशयनं 'a bed in a. place (in the current of wind)'. 3 असार, कल्प, खपुष्पवत् *ind.* -Aeronaut, *s.* वैमानिकः.

Ait, *s.* पुलिनं, अन्तरीपं.

Ajar, *adv.* अर्धविवृत *a.*

Akin, *a.* सगोत्र, सनाभि, सजातीय. 2 सदृश (शी *f.*), समान, संबंधिन्.

Alack, *See* **Alas.**

Alacrity, *s.* औत्सुक्यं, उत्साहः. 2 शीघ्रत्वं, क्षिप्रता, अविलंबः.

Alar, *a.* सपक्ष.

Alarm, *s.* त्रासः, शंका, भयं, साध्वसं. 2 साहनिकं. 3 भयध्वनिः, भयाक्रंदनं; 'a. bell' भयसूचको घंटानादः. 4 प्राग्भयसूचना. -*v. t.* प्राक् सूचनां दा 3 U. 2 भी c., संत्रस् c., उद्विज् c. -ed, *a.* भीत, उद्विग्न, भयार्त, चकित. -ing, *a.* भयावह उद्वेगकर (री *f.*), त्रासजनन (नी *f.*), भयप्रद. -ist, *s.* भयोत्पादकः. -Alarum, *s.* साहनिकं, भयध्वनिः, प्रबोधघंटा.

Alas, *interj.* कष्टं, हा, हंत, हा धिक्, अहह, अहो बत. 2 अत्याहितं, अब्रह्मण्यं.
Alate, *a.* *See* 'Alar'
Albeit, *adv.* यद्यपि.
Albescent, *a.* ईषच्छ्वेत, श्वेतप्राय.
Albugineous, *a.* अंडशुक्लांशोपम.
Albugo, *s.* शुक्लं ; चक्षूरोगः.
Albumen, *s.* अंडशुक्लांशः.
Alchemy, *s.* रसविद्या, रससिद्धि *f.* **-Alchemist,** *s.* रसायनविद् *m.*, रसज्ञः.
Alcohol, *s.* मद्यसारः.
Alcoran, *s.* महंमदीय धर्मग्रंथः.
Alcove, *s.* कुंजः, पर्णशाला, निभृतस्थानं.
Alderman, *s.* पुराध्यक्षः ; वृद्ध-गुरु-जनः.
Ale, *s.* यवसुरा-रं, मद्यं ; 'a. house' शुंडा, पानागारं; 'keeper of an a. house' शौंडिकः.
Aleatory, *a.* यदृच्छाधीन.
Alert, *a.* जागरूक, दक्ष, सावधान, अवहित, अतंद्र, उद्यमिन्, उद्योगिन्. **-ness,** *s.* जागरूकता, अवधानं, दक्षता.
Alias, *adv.* अन्यथा (-अभिहित, *a.*); ex. by इति अपरनामधेय, *a.*
Alibi, *s.* अन्यस्थानवर्तित्वं.
Algebra, *s.* बीजगणितं. **-ical,** *a.* बीजविषयक.
Alien, *a.* विदेशीय, अन्यदेशीय. 2 विरक्त, विरुद्ध, भिन्न, अप्रस्तुत. **-ate,** *v. t.* (affection) विघट् c., विश्लिष् c., भिद् c., विभिद् 7 P or c., विच्छिद् 7 P. as (person) विरंज् c., वि-अप-रञ्ज् ... 8 U. 3 पराधीन *a.* कृ, परस्वत्वे प्रतिपद् c. **-ation,** *s.* विघटनं, विरागः, विरक्ति *f.*
Alight, *v. i.* अवतॄ 1 P, उपविश् 6 P, अवनिपत् 1 P.
Alight, *a.* प्रदीप्त.
Alike, *a.* सदृश (शी *f.*), तुल्य, समान, सम.
Aliment, *s.* आहारः, भोजनं. **-Al, -Ary,** *a.* पोषक, पुष्टिमद्, शक्तिवर्धक. **-ation,** *s.* पोषणं, भरणं.
Alive, *a.* जीवत् (न्ती *f.*), संजीव, सचेतन ; 'I caught him a.' जीवग्राहमग्रहीषं (D. K. II. 4). 2 अभिज्ञ (with gen.), or विद् 2 P, *See* **Know.**
Alkali, *s.* क्षारः, सर्जिका, *See* **Natron.** *a.* **-fy,** *v. t.* क्षारीकृ 8 U. **-ne,** *a.* क्षारस्वभाव, क्षारविशिष्ट.
All, *s.* सर्वं, अखिलं, साकल्यं. *-a.* सर्व-विश्व, *pron. a.*, अखिल, सकल, कृत्स्न, निखिल, समस्त ; 'not at a.' न किमपि, न मनागपि 'at a. times.' सर्वदा; 'a. but' प्राय, कल्प, in comp.; 'a. but dead' मृतप्राय, छिन्नप्राय 'a. but cut'; 'a. of a sudden' अकस्मात्, सहसा, सपदि, एकपदे ; 'this is not a.' एतावतापि कोपो &c. न ...; 'a. I can' यथाशक्ति, यथासामर्थ्यं ; 'this is a. I can do to serve you' ... विभवो भवंतं सेवितुं (M. 2); 'by a. means' सर्वथा ; 'a.-in-a. of one's life' जीवितसर्वस्वं ; 'a. at once' युगपद् ; 'a. round,' सर्वतः, सर्वदिक्षु, समंततः ; 'in a.' साकल्येन, पिंडीकृत्य, मिलित्वा ; 'give me 20 rupees in a.' एवं पिंडीकृत्य मह्यं विंशतिं रूप्यकाणि देहि, सर्वे मिलित्वा सप्त वयं 'we are 7 in a.'; 'a.-bearing' सर्वंसह ; 'a.-conquering' सर्वंदमन, सर्वंजय, सर्वजित् ; 'a.-destroying' सर्वंकष ; 'a.-knowing' सर्वज्ञ, सर्वविद् ; 'a.-pervading' सर्वव्यापिन्, विश्वात्मन्, सर्वगत ; 'a. powerful' सर्वशक्तिमत्.
Allay, *v. t.* प्र-उप-शम् c. (शमयति), निवृत् c., निर्वा c. (वापयति), 'a. ing of heat' निर्वापणं. 2 सांत्व् 10, तुष् c. **-er,** *s.* शमकः, शांतिदः-करः. **-ment,** *s.* प्रशमनं, शांतत्वं ; 'a. of hunger' क्षुत्प्रतिकारः.
Allege, *v. t.* प्रतिज्ञा 9 A, वद् 1 P, ब्रू 2 U ; 'the charges a. ed against me' मयि समारोपिता दोषाः. 2 छल कृ 8 U, व्यपदिश् 6 P, मिथ्या वद्. 3 उदाहृ 1 P. **-ation,** *s.* प्रतिज्ञा, उक्ति *f.*, वचनोपन्यासः. 2 दोषारोपः, मिथ्याभियोगः. 3 व्यपदेशः, छद्मन् *n.*, व्याजः.
Allegiance, *s.* निष्ठा, भक्ति *f.*, अनुरागः. 'a. to the king' राजनिष्ठा.
Allegory, *s.* रूपकं, दृष्टांतः. **-ical,** *a.* लाक्षणिक (की *f.*), रूपकमय (यी *f.*). **-ically,** *adv.* दृष्टांततः, दृष्टांतेन. **-ize,** *v. t.* दृष्टांतयति (D.), रूपकेण कृ c.
Alleviate, *v. t.* उप-प्र-शम् c., निवृत् c., सांत्व् 10 ; निर्वा c. (वापयति), लघयति (D.), लघूकृ 8 U. **-ion,** *s.* उप-प्र-शमः, निर्वापणं ; 'a. of sorrow' दुःखावसादनं. **-ive,** *a.* शांतिद, शामक.
Alley, *s.* उद्यानपथः, वीथि-थी *f.* 2 दुर्गममार्गः, संबाधपथः.
Alligate, *v. t.* सं-अनु-बंध् 9 P. **-ion,** *s.* संबंधः, संयोजनं.
Alligator, *s.* नक्रः, ग्राहः.
Alliteration, *s.* अनुप्रासः.
Allocate, *v. t.* स्थाने दा 3 U. **-ion,** *s.* स्थानदानं.
Allot, *v. t.* परिकॢप् c., दा 3 U, विभज् 1 U. **-ment,** *s.* विभागः, विभजनं. 2 अंशः, भागः.
Allow, *v. t.* अनुज्ञा 9 U, अनुमन् 4 A, अनुमुद् 1 A. 2 Give, q. v. 3 ग्रह् 9 P. *See* **Admit.** 4 उप-ईक्ष् 1 A, विषह् 1 A; न कस्मात् ... (Mu. 3); 'I a. my feet to be burnt' ...

चरणानुपेक्षे. 5 (for) न्यूनीकृ 8U, न गण् 10. **-able,** *a.* अनुज्ञेय, अनुमोद्य; 'a. mistake, क्षमार्होपराधः; 'not a.' प्रति-नि-षिद्ध. **-ance,** *s.* अनुज्ञा, अनुमति *f.*, अनुमोदनं. 2 वेतनं, निरूपितमूल्यं, वृत्ति *f.* 3 स्वीकारः; न्यूनीकरणं.

Alloy, *s.* मिश्रणं, दोषः, न्यूनता. 2 अपद्रव्यं, कुप्यं, मिश्रधातुः. **-ed,** *a.* मिश्रित, दूषित; 'un-a. pleasure' केवलं-दुःखासंभिन्नं-सुखं.

Allude, *v. t.* उद्दिश्य-अधिकृत्य वद् 1 P or वच् 2 P or अभिधा 3 U; उद्दिश् 6 P, सूच् 10, लक्षीकृ; अनुसंधा; 'this story a. s to myself' इयं कथा मामेव लक्षीकरोतीति (S.7). **-Allusion,** *s.* उद्देशः, उदाहरणं, कीर्तनं; इंगितं, सूचनं; 'in a. to' अधिकृत्य, समुद्दिश्य.

Allure, *v. t.* हृ 1 P, आकृष् 1 P, वि-प्र-लुभ् c. **-ing,** *a.* प्रलोभक, हारिन्, आकर्षक; 'a. things' प्रलोभनवस्तूनि. **-ment,** *s.* प्र-विलोभनं; वंचनं, विकारहेतुः, आकर्षणं.

Alluvium, *s.* पुलिनं, नदीरयसमाहृता मृत्तिका. **-Alluvial,** *a.* पुलिनमय (यी *f.*).

Ally, *s.* मित्रं, सहायः, पक्ष्यः, सहकारिन् *m.* **-** *v. t.* संबंध् 9 P. 2 संधा 3 U; संयुज् 10, संश्लिष् c. **-Alliance,** *s.* संधिः; 'friendly a.' सख्यं, मैत्री. 2 संबंधः, सपर्कः; 'matrimonial a.' विवाहसंबंधः.

Almanac, *s.* पंजिका, पंचांगं.

Almighty, *a.* सर्वशक्तिमत्, अमितौजस्; सर्वशक्, सर्वसमर्थ.

Almond, *s.* वातामफलं.

Almonry, *s.* भिक्षादानगृहं, भैक्ष्यशाला. **-Almoner,** *s.* भिक्षादाने अधिकृतः.

Almost, *adv.* प्राय, भूयिष्ठ, कल्प, affixed to adj.; 'a. dead' मृतकल्प, मृतप्राय; 'when the night had a. worn away' क्षीणभूयिष्ठायां क्षपायां; 'it is a. dawn now' अधुना प्रभात-प्राया-कल्पा शर्वरी. 2 प्रायः, प्रायशः, 'a. all' प्रायः सर्वे. 3 (With num.) ex. by आसन्न, उप, in comp.; उप-आसन्न-दशाः &c.

Alms, *s.* भैक्ष्य, भिक्षा, भिक्षादानं; 'beg a.' भिक्षाटनं कृ 8 U, भिक्ष्-याच् 1 A; 'a.-giving' भिक्षादानं, त्यागः; 'a. house' अनाथगृहं, भिक्षागेहं; 'a. man' भिक्षुकः, भिक्षाशिन् *m.*

Aloe, *s.* सहा; कुमारीरसोद्भवो बोलः.

Aloft, *adv.* ऊर्ध्वं, उपरि; 'a. in the air' विहायसा, व्योमवर्त्मना.

Alone, *a.* एक, अद्वितीय, एकाकिन्. 2 एव, केवलं, मात्र in comp.

Along, *prep.* अनु in comp. or with acc.; or by instr.; 'a. the way' अनुमार्गं, 'a. the city of Ayodhyâ' अयोध्यानगरीमनु; 'a. a road' मार्गेण. 2 पुरः, अग्रे, पुरस्तात्; 'a. with' सह, सार्धं, *See* **With**; 'all a.' आमधर्मं, प्रथमादवधि; 'a. side' पार्श्वतः; समीपं-पे.

Aloof, *adv.* दूरे, अंतरे, पृथक्; 'standing a.' दूरस्थ; 'keep a.' पृथक् भिधा 3 U, न गण् 10.

Alopecia, *s.* अकेशता, केशहीनत्वं.

Aloud, *adv.* उच्चैः, उच्च-तार-स्वरेण. 2 प्रकाशं, प्र-उत्-मुक्तकंठं (weep a.), 'call a.' शब्दायते (D.).

Alphabet, *s.* वर्णमाला. **-ical,** *a.* वर्णक्रमानुसारिन्. **-ically,** *adv.* वर्णक्रमेण, वर्णानुसारेण.

Already, *adv.* पूर्वं, पुरा, प्राक्, with एव; sometimes by एव alone; 'the moon has a. risen' उदित एव हिमरश्मिः.

Also, *adv.* अपि, च. 2 अपरंच, पुनश्च, अपिच. 3 तद्वत्.

Altar, *s.* वेदि-दी *f.*, चैत्यं, स्थंडिलं.

Alter, *v. t.* अन्यथा कृ 8 U, विपर्यस् 4 P, विपर्यासं नी 1 P, परिवृत् c. 2 विकृ, विरूप् 10, 'a. ed in appearance' भिन्नाकार इव लक्ष्यमाण. **-** *v. i.* परिवृत् 1 A, अन्यथा-अन्यरूप *a.* भू; विपर्यासं या 2 P; **-ation,** *s.* परि(रि) वर्तः, विकारः, विकृति *f.*, विपर्यासः.

Altercate, *v. i.* विवद् 1 A, कलहायते (D.) **-ion,** *s.* विवादः, कलहः, वाग्युद्धं.

Alter-ego, *s.* लिंगदेहः, सूक्ष्मशरीरं.

Alternate, *a.* Ex. by पर्याय in comp.; 'a. service' पर्यायसेवा. **-** *v. t.* परिवृत् c.; ex. by a verb with पर्यायेण. **-ion,** *s.* विपर्ययः, परिवृत्ति *f.*, पर्यायः. **-ive,** *s.* विकल्पः, पक्षः, पक्षांतरं; gen. ex. by words like गतिः, शरणं &c.; 'there is no other a.' अन्या गतिर्नास्ति, अन्यच्छरणं नालोक्यते (Ka. 152) 2 विकल्पः, विभाषा (in grammar). **-ly,** *adv.* पर्यायेण, यथाक्रमं.

Although, *conj.* यद्यपि, अपि.

Altimeter, *s.* उच्चत्वमापकं यंत्रं.

Altitude, *s.* उच्चत्वं, उच्छ्रायः, उत्सेधः.

Altogether, *adv.* सर्वथा, सर्वतः, अशेषतः, साकल्येन. 2 सहित-संहत-एकीकृत-*a.*; समं, एकीकृत्य.

Alum, *s.* स्फटी, तुवरी, सौराष्ट्री, स्फाटिकी.

Alveary, *s.* मधुकोषः; 2 कर्णशष्कुलि *f.*

Always, *adv.* सदा, सर्वदा, अनिशं, सततं, सर्वकालं, निरंतरं, अनवरतं.

Amain, *adv.* प्रसभं, प्रसह्य, बलात्, सवेगं, जवेन.

Amalgam, *s.* कांस्यं, मिश्रधातुः, पारदसंयुक्तधातुः. **-ate,** *v. t.* संमिश्र् 10. 2 संयुज् 10, एकीकृ 8 U, संश्लिष् c. **-ation,** *s.* धातुसंमिश्रणं. 2 संयोजनं, संयोगः, संमेलनं.

Amanuensis, *s.* लेखकः, लिपिकारः.

Amaranth, *s.* अम्लानपुष्पं. 2 अम्लानः, अ-म्लानहा.

Amass, *v. t.* संचि 5 U, संग्रह् 9 P, संह 3 U, राशी-पुञ्जी-कृ 8 U. **-ment,** *s.* संचयः, संग्रहः, &c.

Amatory, *a.* कामिन्, प्रेमशील, शृंगारप्रिय.

Amaze, *v. t.* विस्मि c. (विस्मापयति, विस्मापयते), विस्मयाकुल-साश्चर्य-*a.* कृ 8 U. **-ed,** *a.* विस्मापित, विस्मित, विस्मयाकुल, साश्चर्य. **-ment,** *s.* विस्मयः, आश्चर्यं, विस्मयाकुलत्वं. **-edly,** *adv.* सविस्मयं; साश्चर्यं. **-ing,** *a.* विस्मयकारिन्, विचित्र, अद्भुत. 2 अतिरिक्त; अति pr.

Ambages, *s.* वक्रोक्ति *f.*

Ambassador, *s.* दूतः, राजदूतः, प्रणिधिः, संदेशहरः. **-ship,** **-Ambassage,** *s.* दौत्यं, प्रणिधिकार्यं.

Amber, *s.* तृणमणिः.

Ambidextrous, *a.* उभयहस्तकुशल. 2 असरल, उभयपक्षपातिन्.

Ambient, *a.* व्यापक; निपातिन्, गामिन् in comp. 2 वेष्टक, परिवेष्टक.

Ambiguous, *a.* द्व्यर्थ, संदिग्धार्थ, अव्यक्त, अस्पष्ट, संदिग्ध. **-ly,** *adv.* अस्पष्टं, वक्रोक्त्या, द्व्यर्थतः. **-ness,-Ambiguity,** *s.* वक्रोक्ति *f.*, संदिग्धार्थता, संदेहार्थः.

Ambit, *s.* मंडलं, चक्रवालं, वर्तुलं.

Ambition, *s.* स्पृहा, आकांक्षा. 2 कीर्तिस्पृहा, ऐश्वर्याकांक्षा, उच्चपदवांछा; 'a. o get a throne,' राज्यलोभः -तृष्णा. **-Ambitious,** *a.* सस्पृह, साकांक्ष, ऐश्वर्यप्रेप्सु, यशस्काम; 'who, a. of your throne, has roused your envy' केनाभ्यसूया पदकांक्षिणा ते जनिता (K. III. 4). 2 (Of hopes) दूराधिरोहिन्, उत्सर्पिन्. **-ly,** *adv.* ऐश्वर्याकांक्षया &c.

Amble, *v. i.* ललितं चल् 1 P, प्लु 1 A; धोर् 1 P. **-s.** धोरितं. **-er,** *s.* धोरितगामिन् *m.*

Ambrosia, *s.* अमृतं, सुधा, पीयूषं. **-al,** *a.* अमृतमय (यी *f.*), अमृततुल्य, (*s.*) in comp.

Ambulate, *v. i.* विचर् 1 P, परिक्रम् 1 U, 4 P, इतस्ततश्चर्. **-ion,** *s.* परिक्रमः, पर्यटनं.

Ambush, Ambuscade, *s.* (परावस्कंदनार्थी) निभृते स्थाने; निभृतावस्थिति *f.*; 'they all lay in a.' सर्वे एव ते निभृतं तस्थुः.

Ameliorate, *v. t.* वृध् c., श्रेयस्-साधीयस् कृ 8 U, समुन्नतिं नी 1 P, *See* **Improve.** **-ion,** *s.* वर्धनं, समुन्नति *f.*, श्रेयस्त्वं.

Amen, *adv.* ओम्, भवतु, एवमस्तु, तथास्तु.

Amenable, *a.* पराज्ञावशाधीन, आज्ञाविधायिन्, आज्ञाकर (री *f.*), आयत्त, वशं यात; 'a. to another's power' पराधिकारवशः.

Amend, *v. t.* सं-वि-परि-शुध् c., समा-प्रति-समा-धा 3 U; 'a. one's life' पापान्निवृत् 1 A, पापं त्यक्त्वा धर्ममाचर् 1 P. **-v. i.** शुध् 4 P; समाधा pass., भद्रतर *a.* भू. **-ment,** *s.* संशोधनं; प्रतिसमाधानं. 2 दोषशोधनं &c. **-Amends,** *s.* प्रमार्जनं, निस्तारः, निष्कृति *f.*, शोधनं; 'to make a. for' प्रमृज् 2 P, शुध् c.; *See* **Atone.**

Amenity, *s.* रम्यता, मनोज्ञता.

Amerce, *v. t.* *See* **Punish.**

Amiable, *a.* सुशील, सुप्रिय, सुजन. 2 प्रियदर्शन, रमणीय. **-ness,** *s.* सौजन्यं, सद्भावः, सुशीलत्वं. **-Amiably,** *adv.* सुशीलतया, प्रीत्या, स्नेहभावेन.

Amicable, *a.* मैत्र (त्री *f.*), हित, स्नेहशील; मित्रभावेन; 'a. settlement' मित्रभावेन निर्णयः. **-ness,** *s.* मित्रत्वं, सख्यं, सौहार्दं. **-Amicably,** *adv.* मित्रवत्, मित्रभावेन सौहार्देन.

Amid,-st, *prep.* मध्ये, अंतरे, अभ्यंतरे, (with gen.); मध्यगत-स्थित *a.* 'a. these thoughts he was pierced by an arrow' एवं विचारयन्-एवं विचारनिमग्नः सन्-बाणेन हतः.

Amiss, *a.* दोषिन्, अपराधिन्. 2 अनुचित, अयोग्य. **-adv.** अनुचितं, अयुक्तं; 'take a.' *See* **Misunderstand.**

Amity, *s.* मैत्री, स्नेहभावः, सख्यं, संधिः.

Ammunition, *s.* युद्धसामग्री, युद्धोपकरणानि.

Amnesia, *s.* स्मृति-भ्रंशः-नाशः.

Amnesty, *s.* (राजकृता) दोषक्षमा, दोषाविमोचनं.

Among,-st, *prep.* मध्ये, अभ्यंतरे, (with gen.); ex. by loc. or gen. of noun, 'a. cows the black one gives much milk' गवां गोषु वा कृष्णा बहुक्षीरा (S. K.) काव्येषु नाटकं रम्यं &c.

Amoretto, *s.* Lover, *q. v.*

Amorous, *a.* कामुक, प्रेमशील, रसिक, शृंगारप्रिय. 2 सविलास, सविभ्रम, ललित; 'a. sport' सविलासक्रीडा. **-ly,** *adv.* सकामं, सानुरागं; सविलासं, सविभ्रमं, ललितं.

Amount, *v. i.* उपचि-संख्या- pass.; संपद् 4 A; 'a. ing to' संख्याक in comp.; 'a. to 100' शतसंख्य-संख्याक; 'they a. in all to 24 men' एवं पिंडीकृत्य चतुर्विंशतिर्नराः संपद्यंते; 'thus the families a. to 14' एवमेतान्येकत्र चतुर्दश कुलानि (Ka. 136); 'your whole speech a. s to this' एतावता-एवंच, एष तव वचसो निष्कर्षः-पिंडितार्थः; 'your exertions do not a. to even a hundredth part of mine' तव व्यवसायो ममोद्योगस्य शततमीमपि कलां न-

समुदाय. -s. राशिः, परिमाणं, समुदायः, संख्या, समुच्चयः; 'by any a. of labour' महता श्रमेणापि; 'to the a. of 100' शत-संकर्ष.

Amphibious, *a.* स्थलजलचर. 2 द्विधागति.

Amphibiology, *s.* संदिग्धवचनं, श्लेषः.

Amphitheatre, *s.* रंगः, रंगभूमि *f.*, रंगांगणं.

Ample, *a.* विशाल, विपुल, बृहत्, विस्तीर्ण, विस्तृत. 2 प्रचुर, प्रभूत, बहुल, यथेष्ट. **-ness,** *s.* विशालता. 2 प्राचुर्य. **-Amply,** *adv.* सविस्तरं, प्रचुरं, यथेष्टं; 'he was a. rewarded' तस्मै प्रचुरं पारितोषिकं दत्तं. **-Amplify,** *v. t.* सविस्तरं- विस्तरेण -वर्ण् 10. 2 तन् 8 U, वृध् c., विस्तृ 9 U. **-Amplification, -Amplitude,** *s.* विस्तारः, वृद्धि *f.* 2 महत्त्वं, प्राचुर्य.

Amputate, *v. t.* अंगं छिद् 7 P or निकृत् 6 P. **-ion** *s.* छेदः, कर्तनं.

Amulet, *s.* रक्षाकरंडः.

Amuse, *v. t.* विनुद् c., रम् c., नंद् c.; 'a. oneself' विहृ 1 P, विलस् 1 P, क्रीड् 1 P. **-ment,** *s.* विनोदः, विमर्दनं, क्रीडा, केलि *f.*, विलासः, कौतुकं. **-ing,** *a.* विनोदिन्, विनोदनशील, हृदयंगम, रम्य.

Anachronism, *s.* कालगणनायां प्रमादः or भ्रमः. 2 कालनिर्देशप्रमादः.

Anæsthetic, *a.* संवेदनानाशक.

Anagogy, *s.* गूढार्थः.

Anagraph, *s.* वर्णनं. 2 परिगणनापत्रं.

Analogy, *s.* सादृश्यं, समानता, संबंधः. **-ical, -ous,** *a.* सदृश (शी *f.*), तुल्यरूप, समान, अनुरूप, संबंधिन्, आनुषंगिक (की *f*). **-ly,** *adv.* सादृश्येन, औपम्येन.

Analphabete, *s.* निरक्षर, अनक्षर.

Analyze, *v. t.* व्याकृ 8 U, विभज् 1 U, विच्छिद् 7 P, विभिन्न *a.* -खंडशः -पृथक् -कृ, विश्लिष् c. **-Analysis,** *s.* विभागः, व्यवच्छेदः, विभेदः, व्याकरणं. 2 सारः.

Anaphrodisiac, *a.* कामशामक.

Anarchy, *s.* अशासनं, अनीश्वरता, राजविप्लवः, अराजकता; 'when the country is in a.' अराजके जनपदे. **Anarch, Anarchist,** *a.* अराजकताप्रतिपादक.

Anathema, *s.* अभिशापः, शापः, आक्रोशः. **-tize,** *v. t.* शप् 1 U, आक्रुश् 1 P.

Anatomy, *s.* पृथक्करणं, विच्छेदः. 2 शरीरव्यवच्छेद-विद्या-शास्त्रं. **-ize,** *v. t.* (शरीरं) व्यवच्छिद् 7 P, पृथक् कृ. 2 चिनु 5 U, व्याख्या 2 P. **-ist,** *s.* व्यवच्छेदकः.

Ancestor, *s.* पूर्वपुरुषः; a. s पूर्वजाः (pl.), पितरः (pl.), पितृलोकः. **-Ancestral,** *a.* पितृक, पैतृक (की *f.*); 'a. property' पित्र्यं रिक्थं. **-Ancestry,** *s.* पितरः, पितृ-: अ: र: र.

Anchor, *s.* नौबंधनकीलः-लं, लांगलं. **-v. t.** कीलेन बंध् 9 P, स्थिरीकृ, मतिं निवश् 7 U or प्रतिहन् 2 P.

Anchorite, *s.* यतिः, आरण्यकः, संन्यासिन् *m.*, वनवासिन् *m.*, वानप्रस्थः.

Ancient, *a.* पुराण, पुरातन (नी *f.*), पूर्व, प्राक्कालीन, प्राक्तन, प्राचीन. **-s.** (a. s) वृद्धाः-प्राचीनपुरुषाः (pl.). 2 ध्वजः, पताका. 3 पताकिन् *m.* **-ly,** *adv.* पुरा, पूर्वं, पूर्वकाले. **-ness,** *s.* प्राचीनता, पुरातनत्वं, &c.

Ancipital, *a.* द्विशीर्षक. 2 संदिग्ध.

And, *conj.* च repeated after each word joined, or after all. In the case of nouns, ex. by Dvandva comps.; 'the Sun and the Moon' आदित्यचंद्रौ. 2 (With adjectives) gen. ex. by Karm. comps.; अलसललितमुग्धानि अंगकानि; (with numerals) by a comp. with अधिक, उत्तर; '100 a. 8' अष्टाधिकं-अष्टोत्तरं शतं. 3 (In the case of verbs) ex. by the use of gerunds; 'go a. tell him' गत्वा तस्मै कथय; sometimes by च in questions; तात अस्ति ते माता स्मरसि च तातं (U. 4). 4 अपि च, अन्यच्च, किं च. 'A. then' अथ, तदनु, ततः; 'a. yet,' तथापि, or ex. by च-च; अतुलभा सकलेंदुमुखी च सा किमपि चेदमनंगविचेष्टितं (V. 2).

Androgynous, *a.* द्विलिंगविशिष्ट.

Aneal, *v. t.* तैलेन अभ्यंज् 7 P.

Anear, *adv.* प्रायः, 2 *prep.* संनिधौ, सकाशे. 3 *v. t.* अभिगम् 1 P, अभ्युपइ 2 P.

Anecdote, *s.* कथा, उपाख्यानं, आख्यायिका.

Anemograph, *s.* वायुवेगदिग्दर्शकं यंत्रं.

Anemometer, *s.* वायुवेगज्ञापकं यंत्रं.

Anent, *prep.* उद्दिश्य, अधिकृत्य, विषये in comp.

Anew, *adv.* पुनः, पुनरपि. 2 अभिनवं.

Angel, *s.* देवदूतः, ईश्वरप्रेष्यः, स्वर्गदूतः, 'you are my a.' त्वं मे प्रियतमा, प्राणप्रेयसी. **-ic, -ical,** *a.* दिव्य, देवदूतोपम, अमानुष, (षी *f.*).

Anger, *s.* क्रोधः, कोपः, अमर्षः, रोषः, मन्युः. **-v. t.** प्रकुप् c., क्रुध् c. **-Angry,** *a.* जातामर्ष, क्रुद्ध, सामर्ष, सरोष, कोपिन्, कुपित, क्रुद्ध, समन्यु; 'to be a.' कुप्-क्रुध्-रुष् 4 P, (with dat.). **-Angrily,** *adv.* सकोपं, सरोषं, कोपात् &c.

Angle, *s.* अस्रः, कोणः. **-v. i.** बडिशेन मत्स्यान् ग्रह् 9 P, उद्धृ-हृ 1 P. **-er,** *s.* मत्स्यवेधकः. **-ing,** *s.* मत्स्यग्रहणं. **-Angular,** *a.* कोणविशिष्ट, अस्रोपेत.

Anguish, *s.* परितापः, पीडा, बाधा, वेदना, यातना, आतंकः; 'a. of mind' मनस्तापः.

Anhelation, *s.* उच्छ्वसनं, हृत्कंपः, वेपथुः.

Animadvert, *v. i.* निंद् 1 P, उपालभ् 1 A; *See* **Censure. 2** परीक्ष् 1 A, चर्चां कृ. **-Animadversion,** *s.* निंदा, उपालंभः. **2** परीक्षणं, चर्चा.

Animal, *s.* जंतुः, प्राणिन् *m.*, जीविन् *m.*, जीवः, जन्मवत् *m.* **2** पशुः, मृगः, तिर्यच् *m.* **-***a.* प्राणिसंबंधिन् &c. **2** चेतन; 'a. food' मांसाहारः; 'a. pleasures' विषयाः, विषयसुखानि; 'a. passions' (carnal) षड्रिपवः-इंद्रियाणि; 'a. kingdom' प्राणिवर्गः. **-cule,** *s.* क्षुद्रजंतुः.

Animate, *v. t.* जीव् c., समा-आ-श्वस् c., प्राण् c. **2** प्रोत्सह् c., जीवं संचर् c., उत्तिज् c., उद्युज् 10, पराणुद् c. **-ed,** *a.* सजीव, चेतन, चर, प्राणिन्. **2** प्रोत्साहित, आश्वासित. **3** प्रफुल्ल, प्रोत्साहनाप्रेरित, सारवत्; 'a. by passion' मदोल्लासित, समद. **-ion,** *s.* जीवसंचारणं, जीवप्रदानं. **2** प्रोत्साहनं, प्रफुल्लता, उल्लासः. **-or,** *s.* प्राणदः, प्रोत्साहकः &c.

Animosity, *s.* द्वेषः, वैरं, विरोधः, मात्सर्यं.

Animus, *s.* चोदना, उद्देशः.

Anise, *s.* छत्रा, शालेयः.

Ankle, *s.* गुल्फः, घुटिका.

Anklet, *s.* नूपुरः-रं, मंजीरं.

Annals, *s.* वार्षिकवृत्तांतः, वार्षिकवृत्तेतिहासः. **2** पुरावृत्तकथा, चरित्राख्यानं. **-Annalist,** *s.* चरित्रलेखकः.

Annex, *v. t.* संयुज् 10, अनुबंध् 9 P, उपाधा 3 U; 'Oudh was a.ed to the British territory' अयोध्यादेश आंग्लराज्यांगं कृतः,-राज्येन संयोजितः. **2** अंते निर्दिश् 6 P; 'a list of names is a. ed' नामावली लेखांते दत्ता, नामानि लेखांते निर्दिष्टानि. **-ation,** *s.* संयोजनं, अनुबंधनं; "a thing annexed' अनुबंधः. **-ed,** *a.* संयोजित, उपाहित.

Annihilate, *v. t.* उत्-समुत्-छिद् 7 P, उन्मूल् 10, अप-उत्-सद् c., नश् c., विलुप् c. **-ion,** *s.* उच्छेदः, क्षयः, अवसादनं, विलोपः, विनाशः; प्रलयः (of the world).

Anniversary, *a.* सांवत्सरिक-वार्षिक (की *f.*). **-***s.* सांवत्सरिको विधिः; a. of birth' जन्मदिवसः; 'a. of death' मृततिथिः.

Annotate, *v. t.* टीकां-भाष्यं-लिख् 6 P (with gen.), व्याख्या 2 P, व्याचक्ष् 2 A. **-ion,** *s.* टीका, व्याख्यानं, भाष्यं, टिप्पणी. **-or,** *s.* टीकाकारः, टीका-भाष्य-कृत् *m.*

Announce, *v. t.* आख्या 2 P or c., निविद् c., विघुष् 10, प्रकाश् c. **-er,** *s.* आख्यायकः, संदेशहरः. **-ment,** *s.* ख्यापनं, निवेदनं, विघोषणा. **2** वार्ता, समाचारः, संदेशः.

Annoy, *v. t.* बाध् 1 A, पीड् 10, दु 5 P, *See* **Afflict. -ance,** *s.* पीडा, व्यथा, क्लेशः, बाधा, दुःखं; 'a source of a.' कंटकः. **-er,** *s.* पीडा-व्यथा-करः. **-ing,** *a.* बाधक, दुःखद.

Annual, *a.* वार्षिक-सांवत्सरिक-आब्दिक (की *f.*); प्रति°. **-ly,** *adv.* प्रतिवर्षं, प्रतिसंवत्सरं, वर्षे वर्षे.

Annuity, *s.* वार्षिकं वेतनं.

Annul, *v. t.* वि-अप-लुप् c., निरस् 4 U, निरर्थक *a.* कृ. **-ment,** *s.* लोपः.

Annular, *a.* मंडलाकार, वलयाकार.

Annulet, *s.* क्षुद्रवलयः-यं.

Anodyne, *s.* शूलघ्नं.

Anoint, *v. t.* लिप् 6 P, दिह् 2 U, अंज् 7 P, समालभ् 1 A. **2** अभिषिच् 6 P; 'a. ed as king' राज्येऽभिषिक्तः. **-er,** अभिषेचकः, विलेपकः. **-ing,** *s.* विलेपनं, अभ्यंजनं, अभिषेकः-षेचनं, समालंभः.

Anomaly, *s.* विधि-नियम-विरोधः, अनियमः, व्यभिचारः. **-ous,** *a.* विधि-नियम-विरुद्ध, अविधि. **-ously,** *adv.* अनियमतः, विधिविरुद्धं.

Anon, *adv.* सपदि, शीघ्रं, झटिति; 'ever and a.' मुहुर्मुहुः.

Anonymous, *a.* अविदित-अनिर्दिष्ट-लेखकनामन्, नाम-संज्ञा-हीन. **-ly,** *adv.* नाम विना, नामनिर्देशं विना.

Another, *a.* अन्य-इतर-पर-अपर, *pron. a.*; or अंतरं in comp.; नगरांतरं 'a. city;' 'in a. place' अन्यत्र; 'in a. manner' अन्यथा; 'at a. time' अन्यदा; 'a. day' अन्येद्युः, परेद्युः; 'one after a.' अनुपूर्वशः, एकैकशः.

Answer, *v. i.* उत्तरं दा 3 U or प्रतिपद् 4 A, प्रतिवच् 2 P, प्रतिभाष् 1 A.; 'he a. ed in the affirmative' बाढं-तथा-इति स प्रत्युवाच. **2** संवद् 1 P, अनुरूप-तुल्य-भू. **3** प्रतिभूः स्था 1 P, प्रातिभाव्यं स्वीकृ 8 U, उत्तरं दा 3 U. **-***v. t.* (a question) कथ् 10, ब्रू 2 U, उत्तरं दा (with gen.); 'a. my letter' मम लेखस्योत्तरं प्रहिणु-प्रेषय. **2** Refute; q. v. **3** क्लृप् 1 A (dat.), उपयुक्त *a.* भू 1 P; 'this will a. my purpose' अनेन मे प्रयोजनं भवेत्, इदं मे इष्टसिद्धये कल्पते. **-***s.* उत्तरं, प्रतिवचनं, प्रत्युक्ति *f*, प्रतिवाच् *f.*, प्रत्युत्तरं. **-Able,** *a.* परानुयोगाधीन, प्रष्टव्य.

Ant, *s.* पिपीलिका. **-hill,** *s.* वल्मीकः-कं, वामलूरः, कूलकः.

Antagonist, *s.* प्रतिपक्षः, विपक्षः, शत्रुः, वैरिन् *m.*, *See* **Enemy. -ic,** *a.* विरुद्ध, विरोधिन्. **Antagonism,** *s.* विरोधः, वैरं.

Antarctic, *a.* दक्षिणकेंद्रीय. **-***s.* दक्षिणकेंद्रं.

Antecedent, *a.* पूर्वगामिन्, पूर्वगत. **-***s.* पूर्वचरितं-वृत्तं. **2** पूर्वगामी शब्दः-शब्दसमूहः.

Antechamber, *s. See* "**Antichamber.**"

Antedate, *v. t.* प्राक्तनदिनं लिख् 1 P.

Antediluvian, *a.* विश्वप्रलयात् प्राक् वर्तमान, अतिपुराण,

Antelope, *s.* कृष्णसारः, हरिणः, एणः, मृगः, कुरंगः.
Anterior, *a.* प्राक्तन (नी *f.*), पूर्व.
Anthem, *s.* ईश्वरस्तुति *f.*, स्तुतिरूपं गीतं.
Anthropology, *s.* मानवजातिशास्त्रं.
Anthropophagi, *s.* क्रव्याशिनः (pl.) राक्षसाः.
Antic, *s.* भंडः, वैहासिकः. –*a.* भंडसदृश (शी *f.*), अयोग्य, असंगत.
Antichamber, *s.* उपशाला.
Anticipate, *v. t.* पूर्वं प्रागेव-ज्ञा 9 U or जिरूप् 10 or ग्रह् 9 P. 2 अग्रतः अनुभू 1 P or भुज् 7 A, पूर्वास्वादनं कृ. –**ion,** *s.* पूर्वमेव ज्ञानं, पूर्वभुक्ति *f.*, पूर्वास्वादनं.
Antidote, *s.* विषघ्नोऽगदः, प्रतिविषं; 'a. against anxiety' चिंताविषघ्नोऽगदः, 'dealer in a. s' विषवैद्यः, जांगुलिकः. 2 प्रतिकारः. –**al,** *a.* विषघ्न (घ्नी *f.*).
Antimony, *s.* स्रोतोंजनं, यामुनं, सौवीरं.
Antipathy, *s.* विरोधः, वैरं, द्वंद्वभावः, विद्वेषः; 'natural a.' शाश्वतिको विरोधः.
Antiphony, *s.* प्रतिध्वनिः, प्रतिगानं.
Antipodes, *s.* प्रतिलोमं; 'living in a.' प्रतिलोमाः.
Antipyrin (e), *s.* ज्वरघ्नं औषधं.
Antiquary, –**rian,** *s.* प्राक्कालीनविषयकोविदः-पंडितः. –*a.* प्राक्कालीन, प्राक्तन (नी *f.*)
Antiquated, Antique, *a.* प्राचीन, पुरातन-प्राक्तन (नी *f.*), पुराण; (style) अप्रचलित, लुप्तप्रयोग (भाषासरणिः).–**Antiquity,** *s.* Ancients, q. v. 2 प्राक्कालः, पूर्वकालः. 3 पुरातनत्वं, प्राक्कालीनत्वं.
Antiseptic, *a.* पूतिनाशक.
Antithesis, *s.* प्रतिपक्षता, विरोधः, अर्थवैपरीत्यं.
Antitype, *s.* मूलमूर्ति *f.*, आदर्शः.
Antler, *s.* हरिणशृंग, मृगविषाणं. –**ed,** *a.* शृंगवत्, विषाणिन्.
Anus, *s.* गुदं, अपानं, पायुः.
Anvil, *s.* सूर्मः-र्मी, स्थूणा.
Anxiety, *s.* चिंता, उत्कंठा, औत्सुक्यं, व्यग्रता, मनस्तापः, चित्तोद्वेगः; आकुलत्वं, उत्कलिका, रणरणकः. –**Anxious,** *a.* व्याकुलित, उद्विग्न, उत्कंठित, चिंतापर, व्यग्र. 2 उत्सुक, इच्छु, सकाम; 'he thus passes a. nights' एवमुद्विग्नस्य यांति रजन्यः; 'to be a. (for)' उत्कंठ् 1 A, उत्सुकायते (D.), उत्सम् 4 P; 'he is a. to see you near' उत्कंठते युष्मत्सन्निकर्षस्य (U. 6.). 3 चिंतामय, उद्वेगकर (री *f.*). –**ly,** *adv.* सोद्वेगं, सोत्कंठं, सचिंतं.
Any, *a.* Ex. by चित्, चन, or अपि with the forms of किम्; 'a. man' कोपि नरः; 'a. woman' काचित्स्त्री &c., 'at a. time' कदाचित्. 2 (Any whosoever) Ex. by forms of यद् with the above; यः कश्चनागच्छतु 'let a. come'; 'I may be a. one' यो वा को वा भवाम्यहं; 'a. how' कथंचित्, येन केन प्रकारेण, यथा कथंचित्; 'a. longer' पुनः, इतः-अतः-परं; 'a. where' कुत्रापि, क्वचिदपि; 'a. thing' ईषदपि, स्तोकमपि.
Apace, *adv.* सत्वरं, शीघ्रं, *See* **Quickly.**
Apart, *adv.* पृथक्; वि-प्र-गत *a.*; 'having knees a.' प्रज्ञुः. 2 निभृतं, रहसि, विजने, एकांते, विविक्ते. 3 दूरे. 4 स्वगतं, जनांतिकं. 'a. from this consideration', 'this consideration a.' इदं कारणं विहाय-त्यक्त्वा, एतदृर्थभिन्न *a.*; 'excellence of virtues a., a woman must have modesty at least' गुणसंपत्त्रिया भवतु, शालीनता पुनरवश्यं स्यादेव. –**ment,** *s.* कोष्ठः, शाला, कक्षा, आवासः, सौधं; 'inner a. s' अंतःपुरं, अंतर्वेश्मन् *n.*
Apathy, *s.* औदासीन्यं, उदासीनता, वैराग्यं. –**etic,** *a.* उदासीन. 2 वीतस्पृह-राग, निःस्पृह, निरीह, निरपेक्ष. 3 निरुत्साह.
Ape, *s.* वानरः, कपिः, प्लव(वं)गमः. 2 अनुकारिन् *m.* –*v. t.* वानरवत् अनुकृ 8 U. (gen.). –**Apish,** *a.* कपेय (यी *f.*), वानरोपम.
Apepsy, *s.* अजीर्णं.
Aperient, *s.* रेचकं, रेचनं.
Aperture, *s.* छिद्रं, रंध्रं, सूक्ष्मं द्वारं.
Apetalous, *a.* दलहीन, निष्पत्र, निर्दल.
Apex, *s.* शिखा, चूडा, अग्रं; शिरस् *n.*, मस्तकं.
Aphorism, *s.* सूत्रं, वचनं.
Apiary, *s.* मधुमक्षिका-करंडः -आगारः-संपुटकः.
Apiece, *adv.* एकैकशः, पृथक् पृथक्, एकैकं.
Apocryphal, *a.* संदिग्धप्रमाण.
Apologue, *s.* उपकथा, उपाख्यानं.
Apology, *s.* क्षमाप्रार्थना, क्षमायाचना, स्वदोषस्वीकारः. 2 व्यप-अप-देशः, छद्मन् *n.* –**ist,** *s.* स्वदोषस्वीकारिन् *m.*, व्यपदेष्टृ *m.* –**ize,** *v. i.* क्षमां याच् 1 A. or प्रार्थ 10 A, स्वदोषं स्वीकृ-अंगीकृ 8 U. 2 व्यपदिश् 6 P, व्यपदेशं-छद्म-कृ. –**Apologetic,** *a.* व्यपदेशक.
Apophlegmatic, *a.* कफनाशन (नी *f.*).
Apophthegm, *s.* सूत्रं, वचनं, नीतिवचनं.
Apoplexy, *s.* अंगविकृति *f.*, संन्यासः.
Apostate, *s.* स्वधर्मत्यागिन् *m.*, स्वधर्मभ्रष्टः-च्युतः, पतितः. –**Apostacy,** *s.* स्वधर्मत्यागः, धर्मभ्रंशः, परधर्माश्रयः. –**Apostatize,** *v. i.* स्वधर्मात् भ्रंश् 1 A, 4 P or पत् 1 P, परधर्माश्रि 1 U.
Apostle, *s.* ईश्वरप्रेरितः, ईश्वरदूतः.

Apostrophe, *s.* संबोधनं. **-ize,** *v. t.* संबुध् c., आमंत्र् 10 A.

Apothecary, *s.* औषधानां विक्रेतृ *m.*, भेषजविक्रयिन् *m.*

Appall, *v. t.* सं-वि-त्रस् c., भी c., उद्विज् c., व्याकुलीकृ 8 U; 'he was a. ed with fear' भयेन विवर्णीभूतः; 'a. ing sight' महात्रासजनकं स्थानं or दर्शनं.

Apparatus, *s.* उपकरणं, सामग्री.

Apparel, *s.* वेशः-षः, वस्त्रं, परिधानं, आभरणं. **-v. t.** वस् c., प्रावृ 5 U, संव्ये 1 P.

Apparent, *a.* व्यक्त, अभिव्यक्त, स्फुट, स्पष्ट, प्रत्यक्ष, प्रकाश, आविर्भूत. 2 मिथ्या *ind.*, अवास्तव (वी *f.*); 'a. praise' व्याजस्तुति *f.* 3 बाह्य, बहिः in comp.; 'to make a.' आविष्कृ, स्पष्टी-प्रकटी-कृ. **-ly,** *adv.* व्यक्तं, स्पष्टं &c. 2 बहिः; 'a wise man acts a. agreeably' विद्वान् जनो बही रमणीयं व्यवहरति (Mal. 1)

Apparition, *s.* आभासः, छाया, आकारः. 2 वेतालः, पिशाचः.

Appeal, *v. i.* पुनर्विचारं प्रार्थ् 10 A. 2 प्रमाणीकृ 8 U, प्रमाणयति (D.); or by प्रमाणं; 'I a. to your lordship in this case' अत्र विषयेऽत्रभवंतं प्रमाणीकरोमि, अत्रभवान् प्रमाणं. **-s.** पुनर्विचारप्रार्थना; प्रमाणीकरणं.

Appear, *v. i.* उदि 2 P, उद्गम् 1 P, प्रकाश् 1 A, प्रादुर्भू 1 P, आविर्भू. 2 उपस्था 1 U, सन्निधा pass. 3 प्रतिभा 2 P, अवभास् 1 A, दृश् pass., लक्ष् pass.; 'so as to a. dead' मृतमिवात्मानं संदर्श्य; 'the witness did not a.' साक्षी नोपतस्थौ. **-ance,** *s.* उदयः, प्रादुर्भावः, आविर्भावः. 2 उपस्थिति *f.* 3 आकारः, आकृति *f.*, रूपं; 'good in a.' शोभनाकृति, सुदृश्य, प्रेक्षणीय. 4 आभासः, छाया, आभा; 'your story has an a. of truth' तव कथा सत्येव प्रतिभाति-अवभासते. 5 अनुमानं.

Appease, *v. t.* सां(शां)त्व् 10, प्र-उप-शम् c. (शमयति), तुष् c., प्रसद् c., अनुनी 1 P; 'to be a. ed' प्रसद् 1 P, प्रशम् 4 P. **-ing,** *s.* सांत्वनं, प्र-उप-शांति *f.*, प्रसादनं, अनुनयः.

Appellation, *s.* *See* **Name.** **-Appellative,** *a.* अभिधायिन्. 2 सामान्य.

Append, *v. t.* अनुबंध् 9 P, उपाधा 3 U, आसंज् c. **-age,** *s.* अनुबंधः; उपाहितभागः. 2 उपकरणं. **-ed,** *s.* संयोजित, उपाहित. **-ix,** *s.* परिशिष्टं, शेषसंग्रहः.

Appertain, *v. i.* *See* **Belong.** **-Appertenance,** *s.* अनुबंधः; उपकरणं, उपस्करः, सामग्री.

Appetite, *s.* कामः, रागः, अभिलाषः, इच्छा, रुचि *f.* 2 बुभुक्षा, क्षुधा-धृ *f.*; 'sensual a.' विषयरुचिः, विषयोपरागः.

Applaud, *v. t.* प्रशंस् 1 P, श्लाघ् 1 A, अभिनंद् 1 P, स्तु 2 U. 2 उपश्लोक् 1 P. **-Applause,** *s.* प्रशंसा, श्लाघा, स्तुति *f.* 2 प्रशंसावाचः (pl.), धन्यवादः; 'he rose to speak amidst loud a.' उच्चैः प्रशंसावाच उदीरयत्सु श्रोतृषु स वक्तुमुदतिष्ठत्. **-Applausive,** *a.* श्लाघान्वित, स्तुतिमय (यी *f.*).

Apple, *s* आताम्रकः,-फलं. 2 (Of the eye) तारा, कनीनिका; 'a. of discord' भेदकलह-बीजं.

Apply, *v. t.* संयुज् 10, न्यस् 4 P, ऋ c (अर्पयति), निविश् c., निधा 3 U, आरुह् c.; 'a. your shoulder to the wheel' चक्रमंसेन उत्तंभय; 'a. ing the hand to my shoulder' अंसे हस्तं निवेश्य &c. 2 विधा 3 U; प्रयुज् 7 A, 10; 'they do not a. the word विषय to happiness' सुखार्थे विषयशब्दं न प्रयुंजते, -शब्दस्य प्रयोगो न दृश्यते. 3 आश्रि 1 U; याच् 1 A, अर्थ् 10 A. 4 (Oneself to) अनुष्ठा 1 P, मनः-चित्तं-समाधा or बंध् 9 P, अभियुज् pass (एते वयं स्वकर्मण्यभियुज्यामहे Mu. 3). **-v. i.** लग् 1 P, सं-अनु-बंध् 9 P. 2 प्रयुज् pass., उपपद् 4 A; oft. by गम् 1 P, इ 2 P; 'this our title does not a. to any one else' द्वितीयगामी न हि शब्द एष नः (R. III. 49); राम इत्ययं शब्द उच्चरित एव मामगात् (R. XI. 73.), विषय in comp.; 'the word ईश्वर not a. ing to anybody else' ईश्वर इत्यनन्यविषयः शब्दः (V. 1). 3 (to, for) याच् 1 A, प्र-अभि-अर्थ् 10 A; 'a. ed for further orders' कोपरो नियोगोऽनुष्ठीयतामिति प्रार्थयामास. **-Appliance,** *s.* उपायः, उपकरणं, सामग्री. **-Application,** *s.* योजनं, विधानं, प्रयोगः, संप्रयोगः, निवेशनं, न्यासः, अर्पणं. 2 मनोनियोगः, चित्तासक्ति *f.*, अभ्यसनं, अध्यवसायः, अभिनिवेशः, आसक्ति *f.*, अनुष्ठानं. 3 उपयोगः, प्रयोजनं. 4 संबंधः; 'a. of this speech to Râma' अस्य वचनस्य रामगामी संबंधः. 5 प्रार्थना. **-Applicable,** *a.* लग्न (ग्नी *f.*), प्रयोज्य. 2 संगत, संबद्ध. **-Applicant,** *s.* प्रार्थयितृ *m.*, अर्थिन् *m.*, याचकः, प्रणयिन् *m.*

Appoint, *v. t.* युज् 7 U, 10, स्था c. (स्थापयति), निधा 3 U. 2 अधिकृ, नियुज् 7 A (with loc.) य इमामाश्रमधर्मे नियुंक्ते (S. 1); व्याविश् 6 P. 3 निर्दिश् 6 P, निरूप् 10; 'a. ed lesson' निर्दिष्टपाठः; 'a. ed time' कृतः कालावधिः, कृतसंकेतः, समयः. **-ment,** *s.* नियोगः, अधिकारः, पदं. 2 नियमः, विधिः, आज्ञा, शासनं. 3 उपकरणं. 4 निरूपणं, स्थापनं. 5 समयः, संकेतः; 'keep your a.' समयमनुरुध्यस्व-प्रतस्व; 'Queen, let us keep (to) our a.' देवि सामयिका भवामः (M. 1.).

Apportion, *See* **Divide.**

Apposite, *a.* युक्त, यथार्थ, संगत. **-ly,** *adv.* स्थाने, यथार्थतः.

Apposition, *s.* समानाधिकरणं, एकान्वयः.

Appraise, *v. t.* (goods) (मूल्यं) निरूप् 10, निर्धृ 10. **-er,** *s.* मूल्यनिरूपकः.

Appreciate, *v. t.* (गुणागुणं) ज्ञा 9 U, अवगम् 1 P, ग्रह् 9 P, विविच् 7 P ; 'appreciator of merits' गुणग्रहीतृ *m.*; गुणज्ञः, मर्मज्ञः. 2 बहु मन् 4 A. **-ion,** *s.* गुणग्रहणं, गुणागुणज्ञानं-विवेचनं.

Apprehend, *v. t.* ग्रह् 9 P, परामृश् 6 P, आसिध् 1 P, आक्रम् 1 U, 4 P, धृ 1 P. 2 आ-वि-परि-शंक् 1 A. 3 मन् 4 A, शंक् 1 A; तर्क् 10, ऊह् 1 U, अनुमा 3 A. 4 अव-अधि-गम् 1 P, उपलभ् 1 A. **-Apprehension,** *s.* ग्रहणं, आसेधः; आ-वि-परि-शंका, अनुमानं, तर्कः,मति *f.*, बुद्धि *f.*; 'of quick a.' तीक्ष्णमति; 'of dull a.' मंदधी, स्थूलबुद्धि. **-Apprehensive,** *a.* आशंकमान, शंकित; 'a. of danger' भयमाशंकमानः.

Apprentice, *s.* शिल्पविद्याशिष्यः, अंतेवासिन् *m.*, शिष्यः. **-ship,** *s.* सेवाकालः, शिष्यत्वकालः.

Apprise (of), *See* **Inform.**

Approach, *v. t.* उप-समुप-अभि-गम् 1 P, °इ-या 2 P, °सृ-सृप् 1 P; समीपं-निकटं-गम् (with gen.). *-v. i.* उप-समुपा-स्था 1 U, °गम्; प्रत्यासद् 1 P. **-s.** आगमः, अवतारः, उपस्थिति *f.*, 'a. of night' दोषागमः, रजन्युपस्थितिः. 2 संनिकर्षः, आसन्नता. 3 प्रवेशः, उपसरणमार्गः. **-ing,** *a.* आसन्न; 'his death a.' आसन्नमरणे तस्मिन्, संनिकृष्ट, समुपस्थित. **-able,** *a.* उपसर्पणीय, समुपगम्य.

Appropriate, *v. t.* आत्मसात् कृ 8 U, स्वाधीनस्वायत्त. **-a.** कृ. 2 प्र-वि-नि-उप-युज् 7 U, 10, उपकल्प् c. **-a.** उपपन्न, संगत, उचित, युक्त; '.. to the occasion' प्रस्तावसदृ. 2 स्वकीय. **-ly,** *adv.* उपपन्नं, युक्तं, स्थाने, यथार्थतः. **-ion,** *s.* आत्मसात्करणं; विनियोगः, उपकल्पनं.

Approve, *v. t.* अनुमुद् 1 A, अनु-सं-मन् 4 A, प्रशंस् 1 P, अभि-प्रति-नंद् 1 P, रुच् 1 A , एतयोर्विवाद एव मे न रोचते (M. 1) 'I do not a. of their very quarrel'; 'I do not a. of your speech' न ते वचोऽभिनंदामि (S. 2) 2 प्रमाणयति (D.) विभू c. **-al,** *s.* अनुमोदनं, अभिनंदनं; संमति *f.*, मतम्; 'he got the a. of his mother' मात्रानुमोदितः. **-ed,** *a.* संमत, प्रशस्त &c., परीक्षित **-Approbation,** *s.* सं-अनु-मति *f.* 2 साधु-धन्यवादः, प्रशंसा.

Approximate, *v. t.* उपनी 1 P, उपस्था c. स्थापयति. **-v. i.** सं-निकटं-वृत् 1 A, आसन्न *a.* भू, *See* **Approach.** 2 Resemble, q. v. **-a.** समीप, आसन्न, संनिकृष्ट; 'a. to 10' आसन्नदशाः. **-ion,** *s.* आसन्नता, उपगमः &c.

April, *s.* चैत्रः, मधुमासः, वैशाखः.

Apron, *s.* (मलनिवारणार्थं) कटिप्रच्छदः, मलवस्त्रं.

Apropos, *adv.* अनुरूपं, यथा in comp.

Apt, *a.* उचित, योग्य, युक्त. 2 Ex by शील in comps., प्रायः with pot. pass. part.; 'youths are a. to forget' युवानो विस्मरणशीलाः; 'lazy boys are a. to be bad boys' अलसैर्बालकैः प्रायो दुर्वृत्तैर्भवितव्यं; 'over-affection is a. to suspect evil; अतिस्नेहः पापशंकी (S. 4) आलु in comp.; 'a. to take pity' दयालु; 'a. to break' भंगुर. 3 दक्ष, कुशल, अभिज्ञ, *See* **Skilful.** 4 त्वरित, चपल, उत्सुक. **-itude,** *s.* योग्यता, पात्रता, औचित्यं. 2 °शीलता, स्वभावः, शीलं. **-ly,** *adv.* यथोचितं, यथोपपन्नं, स्थाने, चातुर्येण, सकौशलं. **-ness,** *s.* योग्यता; कौशलं, पाटवं. 2 शक्ति *f.*, सामर्थ्यं.

Aquarium, *s.* जलचरप्राणिसंग्रहः -पल्वलं.

Aquatic, *a.* जल in comp., जलोद्भव, वारिचर; 'a animal' जलजंतुः, यादस् *n.* 2 जलचर, जलज, वारिज.

Aqueduct, *s.* जलप्रणाली, जलमार्गः, परीवाहः.

Aqueous, *a.* जलमय (यी *f.*), अम्मय, सजल, अनूप.

Aquiline, *a.* गरुडचंचुसदृश (शी *f.*); वक्र, कुंचित; 'having an a. nose' गरुडनासः.

Arable, *a.* कर्षणीय, कृषियोग्य.

Arbiter, *s.* मध्यस्थः; निर्णेतृ *m.*; प्रमाणपुरुषः. 2 ईशः, प्रभुः. **-Arbitrate,** *v.* विचर् c., निर्णी 1 P; मध्यस्थतां गृहीत्वा निर्णी or परिच्छिद् 7 P. **-ion,** *s.* मध्यस्थकृतनिर्णयः; विचारणं, निर्णयः. 2 माध्यस्थं. **-or,** *s.* *See* **Arbiter.**

Arbitrary, *a.* स्वेच्छाचारिन्, कामचारिन्, स्वच्छंद, स्वैरवृत्त. 2 अनियंत्रण, उद्दाम. 3 चपल, अविहित. **-ly,** *adv.* स्वेच्छया, स्वकामतः, स्वैर, निर्यंत्रणं.

Arbour, *s* लतागृहं, कुंजः, निकुंजः-जं, पर्णशाला.

Arc, *s.* वृत्तखंडं, धनुस् *n*

Arcade, *s* आच्छादितपथः-मार्गः

Arcadian, *a.* ग्राम्य, ग्रामीण.

Arch, *s.* खंडमंडलं, वृत्तखंडं ; 'a. of heaven' नभोमंडलं. 2 तोरणः -णं. **-v. t.** मंडलीकृ; तोरणरूपेण निर्मा 3 A, गोलाकारेण आच्छद् 10, 'a.ed सतोरण, न्यस्ततोरण; भुग्न, कुंचित, वक्र, तोरणाकार. **-a.** विदग्ध, धूर्त, चतुर; मुख्य, श्रेष्ठ, उत्तम, प्रधान, अग्रणी; 'a. fiend' पिशाचाग्रणीः; 'a. angel' प्रधानदेवदूतः; 'a. bishop' मुख्यो धर्माध्यक्षः.

Archaic, *a*, आर्ष, प्राचीन.
Archaism, *s*. प्राचीन-आर्ष-प्रयोगः.
Archæology, *s*. पुराणवस्तुशास्त्रं.
Archer, *s*. धन्विन् *m*., धानुष्कः, इषुधरः, निषंगिन् *m*., धनुर्धरः. **-y,** *s*. धनुर्विद्या, शराभ्यासः, धनुर्वेदः.
Archetype, *s*. मूलरूपं, आदर्शः.
Archipelago, *s*, द्वीपसमूहः. **2** द्वीपचितार्णवः.
Architect, *s* स्थपतिः, शिल्पिन् *m* ; 'man is the a. of his own fortune' लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयंति (H. 2). **-ure,** *s*. शिल्पं, वस्तुनिर्माणकौशलं, निर्माणशिल्पं.
Archives, *s*. ग्रंथरक्षागारं. **2** पुरावृत्तं.
Arctic, *a*. उत्तर, उदीचीन, उत्तरकेंद्रीय.
Ardent, *a*. उत्तप्त, प्रचंड, उत्कट, उत्सुक, कुतूहलिन्, उत्साहिन्, व्यग्र ; 'a. love' निरतिशयोनुरागः ; 'a. looks' सतृष्णा दृष्टिः. **-ly,** *adv*. उत्कटं, सतृष्णं, सानुरागं. **-Ardour,** *s*. उत्तापः, अत्युग्रता, निरतिशयः, अतिरेकः, उत्कटता, उत्साहः, व्यग्रता, कुतूहलं, औत्सुक्यं.
Arduous, *a* दुष्कर, यत्नसाध्य, दुःसाध्य, सु-अति-दुष्कर. 2 प्रांशु, दुरारोह, उच्च.
Area, *s*. फलं ; 'a. of a field' क्षेत्रफलं. 2 अंगणं-नं ; 'inner a.' प्रकोष्ठः.
Arena, *s*. रंगः, रंगभूमि *f*., मल्लभू..
Argent, *a*. राजत (ती *f*.), रौप्य (प्यी *f*.).
Argue, *v. i*. तर्क् 10, ऊहापोहं कृ 8 U, विचर् c., विवेचनं कृ. **2** विवद् 1 A, वादे उत्तरं-प्रत्युत्तरं कृ. *-v. t*. प्रमाणेन-तर्केण सिध् c. ; (साधयति), प्रमाणयति (D), युक्तिवादेन सिध् c., युक्त्या तर्क् 10, ऊह् 1 A. **-er,** *s*. तर्किन् *m*, विचारकः, वादिन् *m*. **-Argument,** *s*. युक्ति *f*., उपपत्ति *f*. **2** पक्षः, प्रमाणं, हेतुः, न्यायः, विग्रहः ; 'a wrong a.' पक्षाभासः, हेत्वाभासः. 3 वादानुवादः, विवादः, वाक्कलहः. **4** विषयः, अनुक्रमणिका. **-ative,** *a*. तार्किक (की *f*.), तर्कानुबद्ध. न्यायानुसारिन् उपपत्तिमत्. 2 वादशील, विवादप्रिय. **-ly,** *adv*. सोपपत्तिकं, सवितर्कं, युक्तिवादेन.
Arid, *a*. शुष्क. आतपाक्रांत; 'a. soil' मरुः, मरुस्थलं-ली.
Aright, *adv*. युक्तं, यथातथं, यथास्थानं, सम्यक्, यथार्हं.
Arise, *v. i*. उत्था 1 P ; उत्पद् 4 A, उत्-प्र-सं-भू 1 P, प्रजन् 4 A, प्रवृत् 1 A ; उदि 2 P, उद्गम् 1 P, आविः-प्रादुः-भू, निः-प्र-सृ 1 P, 'a. ing from' ex. by ज, भव, उद्भव, प्रभव, in comp ; स्मरजा पीडा 'torment a. ing from love'. यौवनप्रभवं तमः &c. ; oft. by उत्थ, समुत्थ; नयनसमुत्थं ज्योतिः, Flash arising from the eye.
Aristocracy, *s*. कुलीन-विशिष्ट-जनाः. **2** शिष्टजनतंत्रकं राज्यं. **-Aristocratic,** *a*. कुलीन, अभिजात

Arithmetic, *s*. अंकविद्या-गणितं, परिकर्मन् *n*. **-ian,** *s*. अंकविद्याज्ञः, गणकः.
Ark, *s*. नौ *f*., तरणी, पोतः. **2** आधारः, कोषः.
Arm, *s*. बाहुः, भुजः, भुजा, दोस् *m*. *n*. ; 'fore-a.' प्रकोष्ठः. **2** शाखा. **3** नदीवंकः, वक्रं. **4** शक्ति *f*., बलं वीर्यं; 'got by one's own a.' स्वभुजवीर्येण लब्धं, भुजोपार्जित *-v. t*. सन्नह् c., सज्जीकृ 8 U, अस्त्रैः संयुज् 10, सायुध *a* कृ. *-v. i*. सन्नह् 4 U, सज्जीभू 1 P. **-s** अस्त्रं, शस्त्रं, आयुधः-धं, शस्त्रास्त्रं. **2** विग्रहः, रणसमयः, संग्रामः, युद्धं; 'taking up a.' युद्धारंभः; 'passage of a.' अस्त्र-विद्या. **-ed,** सायुध, सन्नद्ध, सज्ज; 'a. with a sword' सखड्गः. **-less,** *a*. अभुज, अशस्त्र, अनायुध. **-pit, -hole,** *s*. कक्षाक्षः, बाहुमूलं, भुजकोटरः-रं, दोर्मूलं. **-let,** केयूरः-रं, अंगदः-दं. **2** क्षुद्रशाखः, उपशाखा.
Armada, *s*. बृहन्नौसाधनं.
Armament, *s*. बलं, सज्जीकृतं बलं, युद्धोपकरणानि.
Armistice, *s*. युद्धविरति *f*., संधिः, युद्धनिवर्तनं (नियतकालं यावत्).
Armorial, *s*. कावचिक, आयुधीय, आयुधिक. **2** कुलचिन्हसंबंधिन्.
Armour, *s*. वर्मन् *n*., कवचः-चं, कंचुकः, सन्नाहः, तनुवारं, तनुत्रं-त्राण. 'a. for the head' शिरस्त्राणं. **-er,** *s*. शस्त्रकारः, अस्त्रकारः. **-y,** *s*. आयुधागारं, शस्त्रगृहं. **2** शस्त्रसमूहः.
Army, *s*. सेना, सैन्यं, बलं, वाहिनी, चमूः, अनीकं, पृतना, दंडः-डं; 'full a.' चतुरंगं बलं, अक्षौहिणी.
Aroma, *s*. गंधः, आमोदः, परिमलः. **-tic,** *a*. सुरभि, सुगंधि. **2** सुरभित; **a. s** सुगंधिद्रव्याणि. **-tize,** *v. t*. वास् 10.
Around, *prep*. परितः, अभितः (with acc.). *-adv*. समंततः, सर्वतः, विष्वक्, समंतात्.
Arouse, *v. t*. (From sleep) जागृ c., प्रबुध् c. **2** उत्-प्रोत्-सह् c., उत्तिज् c., उत्था c. (उत्थापयति); उद्बुध् c , जन् c. (जनयति).
Arraign, *v. t. See* **Accuse.**
Arrange, *v. t*. रच् 10, घट् c., वि-ऊह् 1 U; सं-विधा 3 U, विनि-अस् 4 U, स्था c.(स्थापयति); 'well a. ed' सुघटित; 'a. in order' यथाक्रमं रच्, संविधा c. &c. **2** (Settle) उपकॢप् c., निर्णी 1 P ; 'I have a. ed to pay his debts' तस्य ऋणं कथं प्रतिदेयमिति मया निर्णीतं-आलोचितं. **-ment,** *s*. रचना, विन्यासः, संविधा, व्यूहनं, क्रमेण स्थापनं, परिपाटि-टी *f*., क्रमः ; 'a. of plot' वस्तुरचना, संविधानकं; सरणि-णी *f*. **2** निर्णयः; 'all a. s for his reception are complete' सर्वास्तत्संभावनासंविधा उपकल्पिताः.
Arrant, *a*. अत्यंत, भृश, अति *pr*. **2** अतिनिंद्य, अतिदुष्ट, निकृष्ट.

Array, *s.* व्यूहः, रचनं, विन्यासः, क्रमः, श्रेणि-णी *f.*, पंक्ति *f.* 2 वेषः, आभरणं, परिच्छदः. —*v. t.* क्रमेण रच् 10, सज्जीकृ 8 U. 2 भूष् 10, अलंकृ; वस्त्रेण आच्छद् 10; 'he was richly a. ed' स महार्घवस्त्रभूषितः,-वस्त्राणि पर्यधत्त.

Arrear, *s.* अवशिष्टदेयं, ऋणशेषं, अशोधितो भागः; 'clear up all a. s' सर्वमवशिष्टदेयं परिशोधयः कार्यपरिशेषं समापयः 'his pay remained in a. s' यथावसरमदत्तत्वात्तस्य वेतनं समुच्छ्रितं.

Arrest, *v. t.* निरुध् 7 U, ग्रह् 9 P, आसिध् 1 P, बंध् 9 P, धृ 1 P, 10; ऋणहेतोः राजाज्ञया धृ 10. 2 निवृत् c., स्तंभ् 9 P or c. (निवर्तयामास नृपस्य दृष्टिं) (R. II. 28); 'the Chitrakuta mountain a. s my eye' बध्नाति मे चक्षुश्चित्रकूटः (R. XIII. 47); 'a. attention' अनन्यमनस् *a.* कृ 8 U, अनन्यचित्त *a.* कृ. —*s* निरोधः, आसेधः, ग्रहणं, धरणं, बंधनं.

Arrive, *v. i.* प्र-सम-अनुप-आप् 5 P, आ-समासद् 1 P, अभि-उपा-गम् 1 P, उपस्था 1 U, प्रपद् 4 A (यौवनदशां प्रपेदे). —**al**, *s.* आगमनं, उपस्थिति *f.* &c.

Arrogance, *s.* औद्धत्यं, दर्पः, अभिमानः, अहंकारः, गर्वः, मदः, अवलेपः, प्रागल्भ्यं, उत्सेकः, आटोपः. —**Arrogant**, *a.* उद्धत, दृप्त, अहंकारयुक्त, प्रगल्भ, समद, गर्वित, अवलिप्त. उत्सिक्त, मानिन्; 'a. lady' मानिनी, प्रमदा. —**ly**, *adv.* उद्धतं, सावलेपं, सदर्पं &c.

Arrogate, *v. t.* समर्थ-अन्यायेन-ग्रह् 9 P or स्वायत्तीकृ 8 U or आदा 3 A. —**ion**, *s.* अन्यायग्रहणं. उपधा.

Arrow, *s.* शरः, बाणः, सायकः, इषुः, कांडः, भल्लः, नाराचः, मार्गणः, शिलीमुखः, विशिखः. —**y**, *a.* बाणवत् &c.; बाणाकार.

Arsenal, *s.* आयुधागारं, शस्त्रगृहं. 2 शस्त्रास्त्रसमूहः.

Arsenic, *s.* फेनाश्मन् *m.*; मनःशिला.

Arson, *s.* गृहदहनापराधः.

Art, *s.* शिल्पं, शिल्पविद्या, कला, व्यवसायः, नाट्यकला 'a. of dancing'. 2 कल्पना, विद्या (science). 3 निपुणता, युक्ति *f.*, कौशलं; साधनं; 'a. s of life' जीवनसाधनानि. 4 व्याजः, कपट, माया, वैदग्ध्यं, चातुर्यं. —**ful**, *a.* चतुर; मायाविन्, 'a. look' चतुरो दृष्टिक्षेपः; विदग्ध, मायावत्. 2 शिल्पेन कृत. 3 निपुण, कुशल. —**fulness**, *s.* चातुर्यं, वैदग्ध्यं, &c —**less**, *a.* ऋजु, अमाय, अकृतक, अकृत्रिम, अव्याज; 'a. ly lovely body' अव्याजमनोहरं वपुः (S. 1). —**lessness**, *s.* सरलता, अमायिता, अकृतकता, आर्जवं, —**Artifice**, *s.* उपायः, छलं, छद्मन् *n.*, व्यपदेशः, कपटं, व्याजः. —**Artificer**, *s.* शिल्पिन् *m.*, कर्म-शिल्प-कारः. 2 कर्तृ *m.*, निर्मातृ *m.* —**Artificial**, *a.* कृत्रिम, कृतक; सव्याज. 2 शिल्पनिर्मित; 'a. mountain' क्रीडापर्वतः. —**Artizan**, **Artist**, *s.* शिल्पिन् *m.*, चित्रकरः. 2 पंडित, निपुणः.

Artery, *s.* धमनी, रक्तवाहिनी.

Article, *s.* द्रव्यं, वस्तु *n*, सामग्री. 2 विषयः, पदं, भागः. 3 समयः, समयपत्रं 4 वृत्तपत्रलेखः.

Articulate, *a.* स्पष्ट, परिस्फुट, व्यक्त. —*v. t.* स्पष्टं-स्फुटं-उच्चर् c. or उदीर् 10. 2 ग्रंथ् 9 P, संयुज् 10, संधा 3 U, —**ness**, *s.* स्पष्टता, स्फुटता; 'a. in uttering syllables' वर्णोच्चारणे स्पष्टता: 'utters articulate sound's परिस्फुटाक्षरां गिरमुदीरयति (Ka. 13) —**ion**, *s.* उच्चारणं &c. 2 संधानं.

Artillery, *s.* अग्न्यस्त्राणि; युद्धास्त्राणि.

As, *conj.*, *adv.* Ex. by वत्, इव; मातृवत् मातरमिव-परदारान् पश्य. 2 यथा, यद्वत्, अनुरूपं-पेण; यथा in comp. (यथोक्तं कथय); 'as-so' यथा-तथा with or without एव 'as-as' यथैव-तथैव (यथैव शांता तथैव सीता दशरथस्य प्रिया (U. 4).' as since-therefore' तथा-तथा, यतः-ततः, यत्-तत्; 'as for instance,' यथा (यथा महानसे), or तथाहि. 2 (On account of) ex. by abl. or instr. of noun. 3 (While) यावत्-तावत् or by pres. part.; 'as he was going, he thought' गच्छन् स इत्थं मनसि चकार; 'as high as' द्घ्न (घ्नी *f*), मात्र, in comp.; 'water as high as the knee' जानुदघ्नं जलं; ऊरुमात्रा भित्तिः &c.; 'as soon as' यावत्-तावत्; or loc. abs. constr. with मात्र or एव; 'as he had spoken' उक्तवत्येव तस्मिन्; 'as before,' यथापुरा, यथापूर्वं, पूर्ववत्; 'as far as यावत् with acc., आ with abl. or in comp (आसमुद्रक्षितीशानां) 'as if,' 'as it were' इव; oft. by मन् 4 A; 'as if the city had been a large tank' नगरं महाकासारं मन्यमानः; 'as follows' इति (इति वक्तुं प्रचक्रमे), or ex. by यथा-यत् at the beginning of narratives; 'it is as follows' तद्यथा; 'as to,' 'as for' तु, तावत्, इति, अधिकृत्य, उद्दिश्य; 'as for merits, he has none' गुणास्तावत्तस्य नैव विद्यते; 'as for doing it quickly it is easy' क्षिप्रमिति सुकरं (निभृतमिति तु चिंतनीयं S. 3). 'as well as' च-च; 'as many as' 'as much as' यावत्-तावत्; 'as yet' अद्यापि, अद्य यावत्. 4 (Connecting words in apposition) ex. by इति; स बंधुरिति मतः, बंधुमतः 'as a father he respects me' पितेति मां स मानयति.

Ascend, *v. i.* उद्इ 2 P, उद्गम् 1 P. —*v. t.* आ-अधि-रुह् 1 P, आ-अधि-क्रम् 1 U, 4 P, (with acc.); 'a. ed the throne राजपद-

प्रताप, सिंहासनमारोह. -ant. *a.* अधिरोहिन्, 2 प्रधान, प्रबल, उत्तम. -*s.* उच्चता,उच्छ्रायः. 2 प्राधान्यं, प्राबल्यं, प्रभुत्वं; 'his stars are in the a.' तस्य जन्मग्रहाः उच्चसंश्रयाः. -ancy, *s.* प्रभुत्वं. प्राधान्यं,प्राबल्यं.-**Ascent,** *s.* आरोहणं, उद्गमः, उदयः, समुत्थानं, अधिरोहणं. 2 अधिरोहणमार्गः, सोपानं; 'difficult of a.' दुरारोह.

Ascertain, *v. t.* ज्ञा 9 U, ज्ञा desid. (जिज्ञासते), निरूप् 10, उपलभ् 1 A. 2 निर्णी 1 P, अव-निर्-धृ 10, निश्चि 5 U, व्यवसो 4 P; 'I shall a. accurately (the truth) about her' तत्त्वत एनामुपलप्स्ये (S. 1); 'for a. ing time' वेलोपलक्षणार्थं (S. 4); -**ment,** *s.* निरूपणं,अव-निर्-धारणं, निर्णयः.

Ascetic, *s.* यतिः, योगिन् *m.*, तापसः, तपस्विन् *m.*, मुनिः, वानप्रस्थः, संन्यासिन् *m.* -**ism,** *s.* वैराग्यं, संन्यासः.

Ascribe, *v. t.* निक्षिप् 6 P, अध्या-आ-रुह् c., (रोपयति), कारणत्वेन संबंध् 9 P; 'a. the defeat to my weakness' मम दौर्बल्यात् पराजयः संभूतः, दौर्बल्यं पराभवस्य कारणं, इति वदंति; 'a. every thing to Fate' दैवायत्तं सर्वमिति वदंति; 'to whom shall I a. the blame' कस्मिन् दोषं निक्षिपामि, कं दोषपक्षे स्थापयामि; पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते (Mr. 1) 'is a. ed to him' &c.

Ashamed, *a.* ह्रीण, ह्रीत, लज्जमान, अपान्वित, लज्जित, व्रीडित, त्रपित, (with instr.); 'to be a.' लज्ज् 6 A, ह्री 3 P, त्रप् 1 A.

Ashes, *s.* भस्मन् *n.*, भसितं, पांशुः, भूति *f.*; 'to reduce to a.' भस्मावशेष *a.* कृ 8U, भस्मी-भस्मसात्-कृ; 'to be reduced to a.' भस्मी-भू 1 P; 'reducing to a.' भस्मीकरणं. -**Ashy,** *a.* पांशुवर्ण, धूसर; 'a. pale' विवर्णवदनः. 2 भस्मलिप्त, भस्मीकृत.

Ashore, *adv.* तीरे, तटे, उत्तीरं, तटस्थ *a.*

Aside, *adv.* एकपार्श्वे; पार्श्वतः. 2 निभृते, एकांते; जनांतिकं, अपवार्य 'a. to one's self' आत्मगतं, स्वगतं.

Ask, *v. t.* याच् 1 A, अर्थ् 10 A, भिक्ष् 1 A. 2 अनुयुज् 7 U प्रच्छ् 6 P, (all governing two acc.) -**ing,** *s.* प्रार्थना, याचना. 2 अनुयोगः, पृच्छा.

Askance, Askew, Aslant, *adv.* तिर्यक्, साचि; 'looking a.' साचिविलोकिन्-अपांगदर्शिन्.

Asleep, *a.* सुप्त, शयित, निद्रित, निद्रालस; 'he fell a.' स निद्रावशं गतः; 'fast a.' गाढसुप्तः, गाढनिद्रावशं गतः.

Aslope, *adv.* प्रवण *a.*; प्रवणं.

Asp, *s.* सर्पः, भुजंगः.

Aspect, *s.* रूपं, आकारः, आकृति *f.*; 'a gloomy a.' विषण्णाकृतिः; 'he had a cheerful a.' तस्य वदनं हर्षोत्फुल्लं बभौ. 2 अवस्था, दशा; "all things wore a different a.' सर्वं विभिन्नावस्थायामवर्तत, विपर्यासं यातं. 3 अवस्थानं; 'my house has a northerly a.' उदगभिमुखं मे गृहं. 4 दर्शनं, निरीक्षणं, संबंधः.

Asperity, *s.* तीव्रता, रौक्ष्यं, कर्कशता 2 विषमता, असमानत्वं.

Asperse, *v. t.* अधिक्षिप् 6 P, परिवद् 1 U. *See* **Censure,** 2 सिच् 6 P, उक्ष् 1 P. -**ion,** *s.* आक्षेपः, निंदा &c. 2 सेकः, प्रोक्षणं.

Aspire, *v. i.* स्पृह् 10 (with dat.), आ-अभि-कांक्ष् 1 U, आप् desid. (ईप्सति) मार्ग् 10 A, अभिलष् 1,4 P. -**ing,** *a.*-**ant,** *s.* आकांक्षिन्, अभिलाषिन्, ईप्सु; 'a. to the throne' राजपदाभिलाषी; 'a. to the fame of a poet' कवियशःप्रार्थी (R. I. 3.); जनोयमुच्चैःपदलंघनोत्सुकः (K. V. 64). -**ation,** *s.* स्पृहा, आकांक्षा, ईप्सा, अभिलाषः, लालसा; 'high a.' महाकांक्षा; 'these are, indeed, high a. s' दूरारूढाः-दूराधिरोहिण्यः खलु एता आकांक्षाः

Aspirate, *s.* महाप्राणः.

Ass, *s.* गर्दभः, खरः, रासभः, 'a. headed' मंदधी, खरबुद्धि. -**Asinine,** *a.* रासभीय, खरसंबंधिन्.

Assafœtida, *s.* हिंगु *n.*, जतुकं, बाह्लीकं, रामठं, सहस्रवेधि *n.*

Assail, *v. t.* *See* **Attack,** 'the character of the thing is a. ed' दोषैर्रूपः स्पृश्यते (Mr. 9). -**ant,** *s.* अभियोक्तृ *m.*, आक्रामकः.

Assassin, *s.* घातकः, हंतृ *m.*, उपांशुघातकः, प्राणहारकः. -**ate,** *v. t.* हन् c. (घातयति), मृ c., व्यापद् c., निभृतं हन् 2 P, वध-हत्यां-कृ (with gen.) -**ation,** *s.* वधः, घातः, उपांशु-निभृत-वधः.

Assault, *v. t., s.* *See* **Attack.**

Assay, *s.* परीक्षा, निकषः. 2 प्रारंभः, प्रथमाप्रवृत्ति *f.* -*v. t.* परीक्ष् 1 A,2 प्रयत् 1 A, *See* **Attempt.**

Assemble, *v. i.* समागम् 1 P, संमिल् 6 P, समुद्-समा-समभि-इ 2 P, संनिपत् 1 P, संगम् 1 A, एकीभू, एकत्र इ, संकुलीभू. -*v. t.* c. of roots above; समा-समुपा-हृ 1 P, एकत्र कृ 8 U. -**Assembly,** *s.* सभा, सदस् *f. n.*, समाजः, संसद् *f.*, परिषद् *f.*; 'a. house' सभागृहं, गोष्ठीस्थानं; 'a. hall' आस्थानमंडपः-गृहं, आस्थानी-नं; 'a. room' इंद्रकं, आस्थानं. -**Assemblage,** *s.* समूहः, संघातः, समाहारः, समुच्चयः, वृंदं, चयः, समुदायः, निवहः, समवायः, गणः, ओघः, संघः, ग्रामः in comp.; 'a. of kings' राजकं.

Assent, *v. i.* अनुज्ञा 9 U, अनुमन् 4 A. 2 ग्रह् 9 P, अंगीकृ 8 U, स्वीकृ, अभ्युप-गम् 1 P, वृ 2 P. -*s.* संमतिः *f.*, अनुमतिः *f.*, अनुज्ञा, अनुमोदनं. 2 अंगीकारः अभ्युपगमः.

Assert, *v. t.* प्रतिपद् c., *see* **Affirm.** -**ion,** *s.* वचनं; प्रतिज्ञा, पूर्वपक्षः.

Assess, *v. t.* देयं करं निरूप् 10 or निर्धृ 10 or दा c. (दापयति).-**ment,** *s.* करनिर्धारणं; राजस्वग्रहणं. 2 करः, बलिः, शुल्कः-ल्कं, राजस्वं. -**or,** *s.* सभ्यः, सभासद् *m.* 2 करशुल्क-ग्राहिन् *m.*

Assets, *s.* विभवः, संपत्ति *f.*

Asseverate, *v. i.* सप्रतिज्ञं-सशपथं-वद् 1 P. -**ion,** *s.* शपथपूर्वकं वचनं, दृढोक्ति *f.*

Assiduity, Assiduousness, *s.* व्यवसायः, उद्यमः, तत्परता, अभियोगः, उद्योगः, मनोयोगः, प्रसक्तिः *f.* -**Assiduous,** *a.* उद्यमिन्-व्यवसायिन्-उद्योगिन् ; तत्पर, सोद्योग, प्रसक्त, परायण, अभियोगवत्. -**ly,** *adv.* तत्परतया साभियोगं, सोद्योगं, अविरतं, प्रसक्तं, प्रयत्नतः.

Assign, *v. t.* निरूप् 10, निर्दिश् 6 P. 2 प्र-उप्-क्लृप् c., निर्णी 1 P. 3 नियुज् 7 U,10, स्था c. (स्थापयति). 4 दा 3 U, ऋ c. अर्पयति). 5 Ascribe, q. v. -**ation,** *s.* द्रव्यसमर्पणं-दानं. 2 संकेतः, अभिसारः; 'place of a.' संकेतस्थानं. -**ee,** *s.* प्रतिनिधिः, प्रतिपुरुषः, नियोगिन् *m.* -**ment,** *s.* निर्देशः, समर्पणं, दानं, उपकल्पनं.

Assimilate, *v. t.* सदृशी-एकी-कृ 8 U; 'a. food' परिपाकं नी 1 P, परिणम् c. (णमयति) -**ion,** *s,* समीकरणं. 2 समता, साम्यं, ऐक्यं. 3 परिपाकः, परिणामः, पक्वता.

Assimulate *See* **Pretend.**

Assist, *v. t.* उपकृ 8 U, साहाय्यं-उपकारं-कृ (gen.) ; अनुग्रह् 9 P. -**ance,** *s.* उपकारः ; साहाय्यं, साहित्यं. -**er,** -**ant,** *s.* सहायः, उपकृत् *m.*, उपकारिन् *m.*, साहाय्यकर्तृ *m.* 2 उप in comp. ; a. master' उपगुरुः.

Assize, *s.* न्यायसभा. 2 अर्घपरिमाणं. -*v. t.* अर्घ-मूल्यं-निरूप् 10 or संख्या c. (ख्यापयति) -**er,** *s.* मूल्यनिरूपकः.

Associate, *v. i.* संसर्गं-संगतिं-समागमं-कृ 8 U; संवस् 1 P, सम्मिल् 6 P, सहवासं कृ, संगमगुव्रज् 1 P; 'deer a. with deer' मृगा मृगैः संगमनुव्रजंति. -*v. t.* संयुज् 7 U,10, संश्लिष् c., संगम् c. (गमयति). -*s.* वयस्यः, मित्रं, सहचरः, अनुषंगिन् *m.*, सजुस् *m.*, सहवासिन् *m.* -**ion,** *s.* संगमः, संसर्गः, संगः, समागमः, साहचर्यं, संयोगः, संश्लेषः ; 'a. of the good with the good' सतां सद्भिः संगः (U. 2) 2 सभा, समाजः, पंक्तिः *f.*, परिषद् *f.*

Assort, *v. t.* यथाक्रमं स्था c. (स्थापयति) or रच् 10 or विन्यस् 4 P ; पृथक् कृ 8 U. -**ment,** *s.* विन्यासः, पृथक्करणं, रचना.

Assuage, *v. t.* प्र-उप-शम् c. (शमयति), तुप् c ; शां(सां)त्व् 10 -*v. i.* प्र-उप-शम् 4 P. -**Assusive,** *a.* शांतिमद्, शामक.

Assume, *v. t.* ग्रह् 9 P, धृ 10, आदा 3 A. 2 Arrogate, q. v. 3 ग्रह्, सिद्ध *a.* मन् 4 A; प्रमाणं विना वद् 1 P; 'a. ing to be true 'तत्सत्यमिति गृहीत्वापि;'a.ed silence' कृतकं-मिथ्या-मौनं.-**Ing,** *a. See* **Arrogant.** -**Assumption,** *s* ग्रहणं, धारणं.2 कल्पना; 'on the a. that he is a fool ' स मूर्ख इति मत्वा. 3 प्रतिज्ञा; प्रमेयं.

Assure, *v. t.* प्रति-इ c., प्रतीतिं कृ 8 U, विश्वस् c. 2 दृढीकृ, संस्तंभ् 9 P or c., सुनिश्चित *a.* कृ. (Oneself) प्रति-इ 2 P, विश्वस् 2 P, निश्चयेन कथ् 10, सनिश्चयं-दृढं-वद् 1 P. -**ance,** *s.* विश्वासः, प्रत्ययः, दृढः प्रत्ययः, प्रत्याशा. 2 साहसं, प्रागल्भ्यं. 3 विश्वासकारणं, प्रत्ययहेतुः. 4 योगक्षेमः, अभयवचनं. -**ed,** *a.* असंदिग्ध, सुनिश्चित, असंशय, दृढ.-**edly,** *adv.* नियतं, नूनं, खलु, असंशयं, 'I a. feel, ' 'I feel a. ed ' इति मे निश्चयः, दृढं मन्ये.

Asterisk, *s.* तारकाचिन्हं.

Asterism, *s.* नक्षत्रं, तारा, तारकं-का.

Astern, *adv.* नौपश्चिमभागं प्रति.

Asteroid, *s.* लघुग्रहः.

Asthenia, *s.* दौर्बल्यं, क्षीणता.

Asthma, *s.* श्वासः, श्वासरोगः.-**tic,** *a.* श्वासरोगपीडित.

Astonish, *v. t.* विस्मि c. (विस्माययति, विस्मापयते), विस्मयं जन् c. (जनयति), विस्मयाकुलीकृ 8 U, चकित *a* कृ. -**ed,** *a.* विस्मित, विस्मयाकुल, चकित;'to be a.'विस्मि 1 A, विस्मयवशं गम् 1 P.-**ing,** *a.* विस्मयकर (री *f.*), अद्भुत, साश्चर्य. -**ment,** *s.* विस्मयः, आश्चर्यं, चमत्कारः.

Astound, *v. t.* विमुह् c., विस्मयाकुल *a.* कृ 8 U, व्याकुलीकृ, जडीकृ; 'a. ed with fear' साध्वसजडीकृतः.

Astray, *adv.* उत्पथं; 'who goes a. ' उन्मार्गगामिन् पथभ्रष्ट, भ्रांत, विपथगामिन्; 'to lead a. ' उत्पथं उन्मार्गं-नी 1 P.

Astride, *adv.* प्रसृतजंघं स्थित *a.*, पादौ पृथक् कृत्वा स्थित *a.*

Astringent, *a.* रूक्ष, कषाय. 2 संकोचनशील. -*s.* स्तंभकं.

Astrology, *s.* ज्योतिषं, नक्षत्रविद्या, दैवज्ञविद्या. -**er,** *s.* गणकः, दैवज्ञः, ज्योतिषिकः, कार्तांतिकः, दैवचिंतकः, मौहूर्तिकः, सांवत्सरिकः. -**ical,** *a.* ज्योतिष (षी *f.*), नक्षत्र in comp.

Astronomy, *s.* ज्योतिःशास्त्रं, ज्योतिषं, खगोलविद्या. **-er,** *s.* ज्योतिर्विद् *m.*, ज्योतिःशास्त्रज्ञः, ज्योतिषिकः, खगोलविद्याभिज्ञः. **-ical,** *a.* ज्योतिष (षी *f.*), नाक्षत्रिक (की *f.*), खगोलविद्याविषयक.

Astute, *a.* विदग्ध, चतुर, निपुण, कार्यदक्ष.

Asunder. *adv.* पृथक्, विरलं, खगत-मगत *a.*; oft. by वि; 'throw a.' विक्षिप् 6 P; 'burst a.' विदीर्ण &c.

Asylum, *s.* आश्रमः. **2** आश्रयः, शरणं, संश्रयः, गति *f.*; 'seek a. with' आ-समुपाश्रि 1 U.

At, *prep.* (Denoting *time* or *place*) by loc. of noun; 'a Kasi' काश्यां; 'a that time' तस्मिन्काले. **2** In other senses, by instr. or abl., oft. by gerund, or loc. abs.; 'a. this' इदं श्रुत्वा; 'a. his arrival' संप्राप्ते तस्मिन्; 'a. his advice' तस्योपदेशेन; 'a. what price' कियता मूल्येन; 'a. first' प्रथमं; 'a. last' अंततः, 'at once' युगपत्, समं; 'a. all' मनागपि, किमपि.

Atelier, *s.* चित्रकर्मगृहं.

Atheist, *s.* नास्तिकः अनीश्वरवादिन् *m.*, निरीश्वरः. **-ical,** *a.* नास्तिकवृत्ति. **-Atheism,** *s.* नास्तिक्यं, ईश्वरनिंदा.

Athlete, *s.* मल्लः, मल्लयोद्धृ *m.* **-Athletic,** *a.* मल्ल, बाहुवीर, बलवत् संनद्धशरीर; 'a exercise, spor s' व्यायामः.

Athwart, *prep.* विलोमं; व्यत्यस्तं; पारं, प्रति pr.

Atlas, *s.* देशालेख्यसंग्रहः.

Atmosphere, *s.* गगनं, आकाशः-शं, अंतरि(री)क्षं, नभस् *n.* **2** शून्यं.**-ical,** *a.* आंतरिक्ष (क्षी *f.*), वायव (वी *f.*), आकाशीय.

Atom, *s.* परमाणुः, अणुः, कणः, लवः, लेशः; 's. ic theory' परमाणुवादः. **-ical,** *a.* परमाणुमय (यी *f.*), सूक्ष्म. **2** अणुविषय, अणुविषयक.

Atone, *v. i.* प्रायश्चित्तं कृ 8 U, निष्कृतिं कृ, प्रायश्चित्तेन परिशुध् c.; प्रमृज् 2 P; उपचारातिक्रमं प्रमार्ष्टुमयमस्मत्कमारंभः (M. 4) 'to a. for the slighting or prostration &c. अनुनी 1 P, संधा 3 U, प्रशम् c (शमयति) **-ment,** *s.* प्रायश्चित्तं, निष्कृति *f.* **2** प्रमार्जनं

Atonic, *a.* अग्निनाशक. अतेजस्विन्.

Atrabilious, *a.* दुर्मनस्, विमनस्क.

Atramentous, *a.* *See* **Black**

Atrocious, *a.* घोर, बीभत्स (of things); अतिपापिन् अतिदुर्वृत्त, पापिष्ठ, नृशंस. **-ness,-Atrocity,** *s.* नृशंसता, बीभत्सता, घोरता. **2** अतिपापं, घोरकर्मन् *n.*

Atrophy, *s.* क्षयः क्षयरोगः, अन्नाभावः.

Attach, *v. t.* आसंज् c अनुरंज् c, संबंध् c., a. great importance to public censure' लोकापवादो बलवान्मतो मे (R. xiv. 40) 'a. friends to you by virtue' सदाचरणेनात्मनि मित्राण्यासंजय-अनुरंजय. **2** आसिध् 1 P, आक्रम् 1 U, 4 P, धृ 10. **3** Ascribe, q. v. **-v.** *i.* संबंध् 9 P, अनुबन्ध् 4, भू 1 P. **-ed,** *a.* अनुरक्त, आसक्त, संप्रसक्त. **2** भक्तिमत् सानुराग, अविरक्त (with loc.); **3** आसिद्ध, आक्रांत. 'to be a.' आसंज्-अनुरंज्-pass.; 'subjects are firmly a. to the king' देवे सुदृढमनुरक्ताः प्रजाः. (Mu. 1); 'fondly a.' बद्धगाढानुरागः **-ment,** *s.* अनुरागः, अभिनिवेशः, आसक्ति *f.*, प्रीति *f.*, भक्ति *f.*, प्रसक्ति *f.*, आसंगः (all with loc.). **2** आसेधः, ग्रहणं.

Attack, *v. t.* अभिद्रु 1 P, अवस्कंद् 1 P, आक्रम् 1 U, 4 P, अभियुज् 7 A; आपत् 1 P, अभिप्रया 2 P, प्रतियुध् 4 A; आसद् c. **2** आ-परा-हन् 2 U: (an opinion &c.) परामृश् 6 P, प्रत्यवस्था, 1 A (with loc.); 'a. ed by a disease' व्याधिग्रस्तः, रोगाक्रांतः. **-s.** अभियोगः, अवस्कंदः-दनं, आपातः, आक्रमः.

Attain, *v.* (to) प्राप् 5 P, प्रति-प्र-आ-पद् 4 A, लभ् 1 A, अधिगम् 1 P, आ-समा-सद् c. अश् 5 A; 'easy to a.' सुलभ *a.*; difficult to .' दुराप *a.*, दुष्प्राप *a.* **-ment,** *s.* अधिगमः, लाभः, अवाप्ति *f.*, प्राप्ति *f.*, समासादनं.

Attainder, *s.* कलंकः, अपयशस् *n.* **2** आधर्षणं, अभियोगः.

Attaint, *v. t.* आधृष् c., अभियुज् 7 A. **2** Stain, q v.

Attemper, *v. t.* यथांशतः मिश्र् 10 or संयुज् 10. **2** नियम् 1 P, शम् c. (शमयति).

Attempt, *v. t.* प्रयत् 1 A, घट् 1 A, उपक्रम् 1 A, आरभ् 1 A, उद्यम् 1 P, प्रवृत् 1 A, चेष्ट् 1 A, व्यवसो 4 P (शमीलतां छेत्तुं व्यवस्यति S. 1). **2** Attack, q. v. **-s.** यत्नः, प्रयत्नः, उद्यमः, आरंभः, प्रयासः, उपक्रमः, प्रवृत्ति *f.*, उद्योगः.

Attend, *v. t.* उपस्था 1 U, संनिधा 3 U, आ-समा-गम् 1 P; 'a. the meeting' संसदि संनिहितो भवः 'a. school' शालां गच्छ. **2** अनु-इ-या 2 P, परिवृ c., सह गम्; 'good luck a. s our lord in every respect' सर्वथा स्पृशंति नः स्वामिनमभ्युदयाः (Rat. 1.) **3** (on, upon) उप-पर्युप-स्था 1 A, उपआस् 2 A, उपचर् 1 P, उपसेव् 1 A, श्रु desid. (शुश्रूषते), (with acc.). **4** (to words) श्रु 5 P, आकर्ण् 10; 'a. to me' मद्वचनं शृणु; 'a. now' सावधानो भव, अवधीयतां; (duty &c.) अवधा 3 U, मनः-धा, निधा, 3 U, मनो युज् 10, (with loc.); अवेक्ष् 1 A. **5** विलंब्-प्रतीक्ष् 1 A. **-ed,** *a.* समेत, परिवृत, समन्वित, अनुयात, सहित, स in comp.; 'a. by maid-

servants' सखीगणपरिवृता, सखीपरिवारा. -ance, *s.* उपस्थानं, संनिधानं; शुश्रूषा, उपचारः, उपासनं, सेवा. -ant, *a.* आनुषंगिक (की *f.*), सहगामिन्, सहचारिन् -*s.* अनुचरः, सेवकः, अनुयायिन् *m.*, परिचरः; 'a group of a. s' अनुयायिवर्गः, परिच्छदः, परिवारः, परिबर्हः. -Attention, *s.* आसक्ति *f.*, अभिनिवेशः, अवधानं, मनोयोगः, अवेक्षा, अप्रमादः, अप्रमत्तता. 2 अनुष्ठानं, उपसेवनं, परायणता; 'a.to one subject' एकाग्रता, निविष्टचित्तता, 'pay a.' अवधानं दा (with loc.). -Attentive, *a.* अवहित, सावधान, दत्तावधान, समाहित, अप्रमत्त, आसक्त, अभिनिविष्ट; 'closely a.' एकाग्र, अनन्यवृत्ति, एकतान, सादर, दक्षिण (to ladies), 'in-a. to household &c.' गृहदारनिरपेक्ष; a. ly *adv.* सावधानं, अवहितं &c.

Attenuate, *v. t.* क्षै c. (क्षपयति), तनूकृ 8 U, क्षीणी-कृशी-कृ. -ed, *a.* कृश, क्षीण, तनु, क्षाम, अपचित (अपचितं गात्रं). -ion, *s.* कृशता, क्षामता, कृशांगत्वं.

Attest, *v. t.* साक्ष्यं दा 3 P; (साक्ष्येण) प्रमाणीकृ 8 U, व्यंज् 7 P, प्रकटीकृ, दिश् 6 P. 2 साक्षिणं कृ, साक्ष्ये आह्वे 1 P. -ation, *s.* साक्ष्यं, प्रमाणं, प्रत्यक्षप्रमाणं.

Attic, *s.* क्षौमः-मं, अट्टः.

Attire, *s.* वेषः, वेशः, वस्त्रं, परिधानं, आभरणं, परिच्छदः, नेपथ्यं, अलंकारः; 'richly attired' गृहीतमहार्घवेषः, उदार-आर्य-नेपथ्यः. -*v. t.* (वस्त्रेण) आच्छद् 10, वेष्ट 1 A, संव्ये 1 P. 2 भूष् 10, *See* Adorn; 'a. oneself' वस् 2 A; a. ing business' नेपथ्यविधानं.

Attitude, *s.* संस्थिति *f.*, संस्थितं, भावः, अवस्था, वृत्ति *f.*, आकारः, 'hostile a.' वैरभावः, विपक्षवृत्तिः.

Attorney, *s.* परकार्यसाधकः, प्रतिपुरुषः, -हस्तकः.

Attract, *v. t.* आ-समा-कृष् 1 P, अनुकृष् (in grammar); आवृज् 10, अभिप्रणी 1 P, विलुट् c., वि-प्र-लुभ् c. -ion, *s.* आ-समाकर्षणं, आवर्जनं; अनुकर्षः-र्षणं. 2 प्र-वि-लोभनं. -ive, *a.* आकर्षक, आकर्षणशील, मनोहर, चित्त-अपहारिन्-हारिन्. 2 मोहक, प्रलोभक.

Attribute, *v. t.* *See* Ascribe; 'a ing to themselves false greatness' आत्मन्यारोपितालीकाभिमानाः (Ka. 108). -*s.* धर्मः, उपाधिः, गुणः. 2 विशेषणं. -ive, *a.* वाच्य, विशेषक-ण.

Attrition, *s.* घर्षणं, पेषणं, क्षयः. 2 अनुतापः, अनुशयः.

Attune, *v. t.* तालोपेत *a.* कृ 8 U. 2 एकतालं कृ, तुल्यस्वरं-तौर्यत्रिकं-कृ.

Auburn, *a.* पिशंग (गी *f.*), गौर (री *f.*), कपिश, पांडुवर्ण.

Auction, *s.* घोषणपूर्वको द्रव्यविक्रयः. -eer, *s.* सघोषणं विक्रेतृ *m.*

Audacious, *a.* प्रगल्भ, निर्भय. 2 साहसिक, निर्लज्ज, धृष्ट, प्रतिभानवत्. -ness, -Audacity, *s.* धृष्टता, प्रागल्भ्य, साहसं, प्रतिभानं. 2 निर्लज्जत्वं.

Audible, *a.* स्फुट, श्रवणक्षम, श्राव्य, कर्णगोचर, श्रोत्रग्राह्य -Audibly, *adv.* स्फुटं; 'in a.' अस्फुटं, निःशब्दं; 'began to sob i.' निःशब्दं रोदितुमारेभे (Ka. 135)

Audience, *s.* समाकर्णनं, श्रवणं, निशमनं. 2 दर्शनं; 'have an a.' दर्शनं लभ् 1 A; (राजदर्शनं लेभे); 'I wish to be favoured with an a.' दर्शनानुग्रहमिच्छामि (M. 4), 'give a.' कर्णं दा 3 P, *See* Attend, (to). 3 प्रेक्षकाः, श्रोतृवर्गः, श्रोतारः. 4 सभा, परिषद् *f.*, रंगः (आलिखित इव सर्वतो रंगः S. 1), 'a. chamber' दर्शनगृहं.

Audit, *v. t* (गणितं) शुध् c., अनुसंधा 3 U, परीक्ष् 1 A. -*s.* गणितशोधनं-परीक्षणं &c. -or, *s.* श्रोतृ *m.* 2 गणितशोधकः-परीक्षकः. -ory, *s.* *See* Audience.

Aught, *s.* किमपि, किंचन, किंचित्.

Augment, *v. t.* वृध् c., एध् c., आप्यै c., प्रचुरीकृ 8 U, उपचि 5 U. -*v. i.* वृध्-एध् 1 A, उपचि pass., प्यै 1 A. -*s.* वृद्धि *f.* 2 आगमः. -ation, *s.* वृद्धि *f.*, वर्धनं. 2 उपचयः, ऋद्धि *f.*, समुन्नति *f.*

Augur, *s.* शकुनज्ञः, निमित्तज्ञः, पूर्वलक्षणज्ञः. -*v. i.* शुभाशुभं परीक्ष् 1 A or आलोच् 10. 2 अनुमा 3 A, शंक् 1 A: 'this does not a. well for the success of your undertaking' तव कार्यसिद्धेर्नैतच्छुभलक्षणं. -y, *s.* निमित्तज्ञानं, शकुनज्ञानं. 2 शकुनं, अजन्यं, पूर्वलक्षणं, निमित्तं.

August, *a.* महनीय, अत्युत्कृष्ट, अतिमहत्, महामहिमन्; ऐश्वर (री *f.*), प्रतापवत्; 'a. queen' आरूढप्रतापा राज्ञी. -*s.* श्रावणः, नभस्यः, नभस् *m.* -ness, *s.* महाप्रतापः, ईश्वरत्वं.

Aunt, *s.* पितृस्व (ष्व) सृ *f.*, मातृस्व (ष्व) सृ *f.*, पितृव्या, मातुलानी, मातुला-ली.

Aural, *a.* *v.* Auricular, *q. v.*

Auricle, *s.* कर्णशष्कुली. -Auricular, *a.* कार्णिक (की *f.*), श्रावण (णी *f.*). 2 कर्णोपकर्णं कथित, जपित, गुप्त.

Auriferous, *a.* सुवर्णमिश्रित

Aurist, *s.* कर्णवैद्य.

Aurora, *s.* उषस् *f.*, अरुणः.

Auspice, *s.* शकुनं, निमित्तं, पूर्वलक्षणं; a. s अनुग्रहः, आश्रयः, प्रसादः. -Auspicious, *a.* शिव, शुभ, शिवं-शुभं-कर, मांगलिक (की *f.*), कल्याण (णी *f.*), मंगल, भद्र; 'a. time' लग्नवेला, शुभलग्नं. 2 श्रीयुक्त, सौभाग्यवत्. 3 प्रसन्न, अनुग्राहिन्. -ly, *adv.* शुभक्षणे;

सौभाग्येन, क्षेमेण. -ness, *s.* कल्याणं, मंगलं, मांगल्यं, सौभाग्यं, भद्रं, क्षेमः-मं, शुभं.

Austere, *a.* तीव्र, उग्र, (तपः), निष्ठुर, कर्कश, कठोर, निर्दय, कठिन; (in taste) शुष्क, रूक्ष, कटु. -ity, *s.* उग्रता, कठोरता &c. 'religious a.' तपस् *n.*, कृच्छ्रं.

Austral, *s.* *See* 'southern.'

Authentic, -al, *a.* अकृत्रिम, तथ्य, प्रमाणयुक्त; अकल्पित, सत्य. -ate, *v. t.* सप्रमाण *a.* कृ 8 U, प्रमाणीकृ. ity, *s.* सप्रमाणता, सत्यता, प्रामाण्यं. -ally, *adv.* सप्रमाणं, प्रमाणानुसारेण.

Author, *s.* कारः-कृत् in comp.; 'a. of Gadādhari' गदाधरीकारः- कृत्; ग्रंथकारः. 2 कृत् *m.*, प्रणेतृ *m.*, लेखकः. 2 प्रवर्तकः, आरंभकः, उत्पादकः, जनकः, संपादयितृ *m.* -ship, कर्तृत्वं, प्रवर्तकता.

Authority, *s.* प्रभुत्वं, प्रभावः, शक्ति *f.* 2 अधिकारः, प्रभुत्वं. 3 ऐश्वर्यं, आधिपत्यं, आज्ञा, शासनं, नियोगः. 4 प्रमाणं, आप्तवचनं, निदर्शनं; 'Pāṇini is an a. in this respect' अत्र विषये पाणिनिः प्रमाणं. 5 प्रामाण्यं, विश्वसनीयता. 6 गुरुत्वं, गौरवं. 7 अधिकारिन् *m.*, नियोगिन् *m.*, अधिकृतः पुरुषः, प्रभुः. -ative, *a.* सप्रमाण, शासनानुरूप, वैधिक (की *f.*); a. ly, *adv.* शासनेन; सप्रमाणं.

Authorize, *v. t.* प्रमाणीकृ 8 U, सप्रमाण *a.* कृ. 2 अधिकृ, नियुज् 7 A, 10. 3 अनुज्ञा 9 U, अनुमन् 4 A; 'a. ed person' अधिकृतः पुरुषः.

Autobiography, *s.* आत्मवृत्तकथनं, आत्मचरितरचनं.

Auto-car, *s.* स्वयंप्रेरितवाहनं-शकटः-रथः.

Autocrat, *s.* सम्राज् *m.*, अधिराजः, अनियंत्रितशासनः.-Autocracy, साम्राज्यं, आधिराज्यं.

Autograph, *s.* स्वहस्तलेखः. -*a.* स्वहस्तलिखित.

Automatic, *a.* स्वयंप्रेरित.

Automaton, *s.* स्वयं-चलद् यंत्रं.

Automobile, *s.* *See* 'Auto-car'.

Autonomy, *s.* स्वयंशासनाधिकारः. Autonomous, *a.* स्वयंशासित.

Autopsy, *s.* स्वयंनिरीक्षणं (शवपरीक्षणं).

Autumn, *s.* शरद् *f.* -al, *a.* शरत्कालीन, शारदीय, शारद (दी *f.*) 2 शरदिज.

Auxiliary, *a.* सहायभूत, उपकारक, सहकारिन्. -*s.* सहायः, उपकारकः, सहकारिन् *m.*

Avail, *v. t.* उपकृ 8 U, अनुग्रह् 9 P; gen. ex. by instr. with अर्थ, गुण &c.: 'what a. s thy weeping, child' वत्स किं रुदितेन. 2 प्र-उप-युज् 7 A, 10; 'a. ing himself of the opportunity' गृहीतावसरः. -*v. i.* सफल *a.* भू, हिताय-फलाय-भू; लाभाय-भू. -*s.* प्रयोजनं, उपयोगः, गुणः. 2 फलं, हितं, लाभः, अर्थः; 'of no a.' निष्फल, व्यर्थ &c. -able, *a.* प्रयोज्य. 2 सफल, हितावह. 3 प्राप्य, लभ्य; 'not a' दुर्लभ, असुलभ, अनुपलभ्य.

Avalanche, *s.* गिरिशिखरस्खलत् हिमराशि *m.*

Avant guard, *s.* सेनामुखं, रणशिरस् *n.*

Avarice, *s.* लोभः, लालसा, जिघृक्षा, वित्तेहा. -Avaricious, *a.* लोभिन्, धनलुब्ध, अर्थपर, मितंपच, लुब्ध, कृपण. -ly, *adv.* अतिलोभेन, कृपणवत्. -ness, *s.* कृपणत्वं, कार्पण्यं, अतिलोभः, लुब्धता.

Avaunt, *interj.* अपेहि, अपसर.

Avenge, *v. t.* प्रतिकृ 8 U, प्रति(ती)कारं कृ, (with gen.); वैरानृण्यं गम् 1 P (with loc. of offender). 2 निर्यत् 10, शुध् c.; 'a. a wrong' वैरनिर्यातनं-वैरसाधनं- कृ. 3 दंड् 10, प्रतिहिंस् 7 P. -er, *s.* प्रतिकर्तृ *m.*, प्रतिहिंसकः, वैरशोधकः.

Avenue, *s.* द्वारं, मार्गः; वीथि *f.*; तरुपंक्ति-वृक्ष-श्रेणि *f.*

Aver, *v. t.* सप्रतिज्ञं-सशपथं वद् 1 P, दृढं वच् 2 P.

Average, *a.* सामान्य, मध्यम. -*s.* मध्यमावस्था, मध्यस्थता; 'on an a.' सामान्यतः, स्थूलप्रमाणेन.

Averse, *a.* पराङ्मुख (खी *f.*), विरक्त, प्रतिकूल, विपरीत, द्वेषिन् 2 अननुकूल, वाम; 'fate being a.' प्रतिकूलतां उपगते विधौ; 'a. to giving intelligence' वृत्तिदानपराङ्मुखः; 'to be a.' (to) अपावृत् 1 A, विरंज् pass. -ness, Aversion, *s.* विरागः, अप्रीति *f.*, द्वेषः, विमति *f.*, प्रतिकूलता, विरक्ति *f.*, पराङ्मुखता (with loc.) 2 त्रासः, भयं.

Avert, *v. t.* सं-परि-हृ 1 P, विनि-अप-नि- वृ c., नि-व्या-अप-वृत् c., अपानुद् 6 P; 'with the face a. ed' विमुख-पराङ्मुख (खी *f.*).

Aviary, *s.* पंजरं, वीतंसः, विटंकः, पक्षिशाला.

Aviation, *s.* आकाशगमनं. -Aviator, *s.* आकाशगामिन् *m.*

Avidity, *s.* Avarice, q. v 2 अतिस्पृहा, कौतूहलं.

Avocation, *s.* कार्यं, व्यापारः, वृत्ति *f.*, कर्मन् *n.* 2 आकर्षणं

Avoid, *v. t.* परिहृ 1 P, वि-परि-वृज् 10, मोक्ष् 1 P, हा 3 P, त्यज् 1 P -Ance,-ing, *s.* त्यागः, वर्जनं, परिहारः-हरणं.

Avouch, *v. t.* सनिश्चयं-सशपथं-वद् 1 P. 2 परार्थं वद्, निर्व्यूह् 1 U.

Avow, *v. t.* प्रकाशं-स्पष्टं-वद् 1 P. 2 स्वीकृ 8 U, अंगीकृ, अभ्युपगम् 1 P. -edly, *adv.* स्पष्टं, प्रकाशं, प्रकटं.

Await, *v. t.* प्रति-ईक्ष् 1 A (तदागमनं प्रतीक्षते) प्रतिपाल् 10, उद्वीक्ष् 1 P 2 प्रत्यासद्

1 P, लग्न *a.* संपद् 4 A: उपस्था 1 U, आपत् 1 P, (with gen.) ; ' destruction (death) a. s those that are born' विपदुत्पत्तिमतामुपस्थिता (R. viii. 83)

Awake, *v. i.* वि-प्र-बुध् 4 A, निद्रां त्यज् 1 P, विनिद्र *a.* भू, जागृ 2 P. —*v. t.* **Awaken,** जागृ *c.*, बुध् *c.*, निद्रां भञ्ज् 7 P. 2 जन् *c.* (जनयति), उत्तिज् *c.*, उत्था *c.* (उत्थापयति) —*a.* जाग्रत् (ती *f.*), उन्निद्र, प्रबुद्ध, प्रजागर, जागरूक.

Award, *v. t.* दा. 3 P. 2 दा *c.* (दापयति). —*s.* निर्णयः; विचारः, आज्ञा.

Aware, *a.* विज्ञापित, सावधान 2 वेदिन्-ज्ञ in comp.; or by ज्ञा 9 U, *See* **Know.**

Away, *a.* परोक्ष, अविद्यमान, अनुपस्थित; दूरस्थ. —*adv.* अलं, कृतं (instr.). 2 अपेहि, अपसर.

Awe, *s.* साध्वसं, भयं, त्रासः, आदरः, संभ्रमः, आदरप्रयुक्तं भयं; ' I approach the king with a. ' चकितं नृपस्य पार्श्वमुपैमि (M. 1); ' Stand in a. of ' भी 3 P. त्रस् 1, 4 P. —*v. t.* भी c., त्रस् c. संभ्रमेण आकुलीकृ 8 U; ' a. ed., struck with awe ' संभ्रांत, विस्मयाकुल; भयाकुल, भयविह्वल, ससाध्वस. **-Awful,** *a* घोर, दारुण, भीषण, भैरव (वी *f.*) (of things). 2 अतितेजस्विन्, महातेजस्, आदरणीय, पूज्य; ' how a. is royal greatness ' अहो दुरासदो राजमहिमा (M. 1). 3 प्रशांतगंभीर (अरण्यश्रीः). **-ly** *adv.* सभयं, अत्यंतं. **-ness,** *s.* तेजस् *n.*; दारुणता, घोरता.

Awhile, *adv.* किंचित्कालं, मुहूर्तं, क्षणं यावत्.

Awkward, *a.* अकुशल, अदक्ष, अक्षिप्र, अपटु. 2 (Manners) ग्राम्य; विरूप, स्थूल. **-ness,** *s.* अदक्षता; ग्राम्यता &c.

Awl, *s.* आरा, चर्मप्रभेदिका

Awn, *s.* शूकं, किंशारुः.

Awning, *s.* वितानं, आच्छादनं.

Awry, *adv.* तिर्यक्, साचि, जिह्मं. 2 विपरीतं, प्रतिलोमं, प्रतिकूलं.

Axe, *s.* टंकः, परशुः, कुठारः, परश्वधः.

Axiom, *s.* तत्त्वं, सिद्धांतः. 2 वचनं, सूत्रं. **-atic,** *a.* स्वयंसिद्ध.

Axis, *s.* अक्षरेखा, अक्षः, ध्रुवः.

Axle, *s.* अक्षाग्रं.

Ay, *adv.* तथेति, एवं, आम्, नूनं :

Ayah, *s.* उपमातृ *f.*, धात्री, आसन्नपरिचारिका.

Aye *adv.* सदा, सर्वदा, अजस्रं.

Azure, *a.* नील, नील-आकाश-वर्ण.

B.

Babble, *v. i.* जल्प् 1 P, प्रलप् 1 P. 2 रहस्यभेदं कृ 8 U. **-ing,** *s.* जल्पः, प्रलपितं. **-er,** *s.* जल्पकः, वाचाटः, वाचालः, प्रलापिन् *m.*, वावदूकः.

Babe, Baby, *s.* शिशुः, शावकः, दारकः (रिका *f.*), स्तनंधयः. **-hood,** *s.* बाल्यं, शैशवं, बालभावः. **-ish,** *a.* बालिश, बालेय.

Babel, *s.* मर्मरः, कोलाहलः, संकीर्णनादः.

Baboon, *s.* वानरः, कपिः, मर्कटः.

Bacchanal } *s.* मद्यपानासक्तः, मद्यप्रियः,
Bacchanalian }

पानरतः.

Bachelor, *s.* अकृतदारपरिग्रहः, अकृतोद्वाहः, अविवाहितः.

Bacilli, *s.* (Pl.) रोगजंतवः.

Back, *s.* पृष्ठं, पृष्ठदेशः; ' lying on the b. ' उत्तानशयः; ' behind one's b. ' परोक्षे-क्षं. —*adv.* प्रति, अपा, नि, परा, with verbs ; पुनर्निवृत् 1 A ' come . ' ' give b. ' प्रतिदा 3 U. —*prep. See* **Before.** —*v. t.* अनुमुद् 1 A, समर्थ् 10 रक्ष् 1 P. 2 (horse), आ-अधि-रुह् 1 P. 3 पराणुद् 6 P, *See* **Drive.-bite,** *v. t.* परोक्षे अधिक्षिप् 6 P, परिवद् 1 U, असूयति (D.) with dat.; पृष्ठमांसं अद् 2 P or खाद् 1 P (with gen.). **-biter,** *s.* पिशुनः, पृष्ठमांसादः, परिवादरतः. **-biting,** *s.* पैशुन्यं, परि (री) वादः **-bone,** *s.* पृष्ठवंशः, कशेरुका. **-door,** *s.* पक्षद्वारं, पक्षकं. **-gammon,** *s.* चर्मपट्टिकाक्रीडा. **-ground,** *s.* पश्चाद्भूमि *f.*; ' throw into the b. ' (lit.) दृष्टिपथाद्विवाह् 10, निभृते स्था c. (स्थापयति) ; (fig.) ' Urvas'I throws LakshmI into the b. ' उर्वशी प्रत्यादेशः श्रियः (V. 1); रतेरपि ह्रीपदमादधाति (K. III 57). **-room,** *s.* अंतर्गृहं, अंतः-उप-शाला. **-side,** *s.* पृष्ठभागः-देशः. **-slide,** *v. i.* स्वधर्मात् भ्रंश् 1 A, 4 P or च्यु 1 A. **-stairs,** *s.* उप-प्रच्छन्नसोपानं; ' b. influence ' प्रच्छन्न-सामर्थ्य-गुणः. **-ward,** *a.* पराङ्मुख (खी *f.*), अतीतकाल. 2 मंदधी- मति, मंद, (of a boy). 3 अनिच्छु, प्रतीप.**-wards,** *adv* परा, प्रति, with verbs; पृष्ठतः, पष्ठभागे-देशे. 2 पश्चात्, प्रतीपं; गतागतं; ' move b. and forward ' गतागतं-गमनागमनं कृ 8 U.

Bacon, *s.* शूकरमांसं.

Bacteria, *s.* (Pl.) रोगजंतवः.

Bad, *a.* निंदित, गर्ह्य. 2 अशुभ, अभद्र. 3 असार निर्गुण, अहित; 4 सदोष, अशुद्ध; gen. ex- by दुः, वि, कु, किं, कृत, अप, prefixed; ' a b. man ' दुर्जनः; दुर्दैवं &c. ; कुपथः ' a b. way; ' कुमतिः; किंसखा ' a b. friend ' ; 'b. coin,' कूटनाणकं; 'b. debts,' अप्रतिलभ्य-

क्षणं, अपयशः ' b. fame ', infamy; कदश्वः ' a b. horse. ' **-ly,** *adv.* Gen. Ex. by दुर्, कु; 'b. prepared ' कुनिर्मित; ' smells b. ' दुर्गंधः अस्य; ' b. bitten ' तीव्रं-बलवत्-असुखं-दष्ट; 'b. off' दुःस्थित, कष्टापन्न, दुर्गत. **-ness,** *s.* Ex. by (*a.*); ' b. of result ' कुपरिणामः; दुराचारः: 2 दुर्जनता, दुष्टता. 3 निःसारता, निर्गुणता, अभद्रता. 4 अशुद्धता, सदोषता.

Badge, *s.* चिह्नं, लक्षणं.

Badinage, *s.* उपहासः, लघूक्ति *f.* ढहरी, नर्मन् *n.*

Baffle, *v. t.* व्यर्थी-मोघी-कृ 8 U. खंड् 10, भंज् 7 P, प्रति-वि-हन् 2 P. 2 पराभू 1 U, पराजि 1 A; ' b. ed in efforts ' भग्नोद्यमः; ' the scene b. s description ' वर्णनविषयातिक्रांतं तत्स्थानं. **-ed,** *a.* खंडित, भग्नाश, मोघाश; पराजित.

Bag, *s.* पुटः-टं, पसेवः, स्यूतः, कोषः; ' leather b. ' चर्मभस्त्रिका. **-** *v. t.* स्यूते निधा 3 U. 'to let the cat out of the b', गुह्यं स्फुट् c., गुह्यस्फोटं कृ 8 U.

Bagatelle, *s.* क्षुद्रविषयः, अगुर्वर्थः.

Baggage, *s.* सामग्री, उपकरणं, साधनं; ' bag and b. ' सर्वमपि गृहीत्वा. किमपि नावशेष्य.

Bagnio, *s.* स्नानागारं. 2 वेशवासः, वेश्यालयः.

Bah, *interj.* अहह, धिक्.

Bail, *s.* प्रतिभूः, लग्नकः, प्रातिभाव्यं; ' admitted to b. ' प्रतिभूदानेन मुक्तः. **-** *v. t.* लग्नकं दा 3 U. दत्त्वा मुच् c. 2 पोतं निर्जलीं कृ 8 U.

Bailiff, *s.* आसेद्धृ *m.*, ग्राहकः.

Bairn, *s. See* **Babe.**

Bait, *s.* आमिषं; ' b. fixed to a fish-hook ' बडिशयुतं पिशितं. 2 प्र-वि-लोभनं. 3 प्रवासोपहारः. **-** *v. t.* प्र-विलुभ् c. 2 आमिषं दा 3 U (with dat.), आमिषं बडिशे निधा 3 U or यु 2 P or निविश् c., ' this is surely a b. to catch me ' मां वशीकर्तुं नूनमिदमामिषं प्रकल्पितं. 3 (horses) विश्रम् c.: भुज् c. 4 *See* ' Harass. ' 5 (प्रवासे) मार्गे उपहारं कृ 8 U. **-** *v. i.* भोजनार्थं विश्रम् 4 P.

Bake, *v. t.* (कंदौ) पच् 1 P, तप् c., भ्रस्ज् 6 P. **-ed,** *a.* पक्व; ' b. brick ' पक्वेष्टका; कंदुपक्व. **-er,** *s.* कांदविकः; आपूपिकः. **-house,** *s.* आपाकः; कंदु *m. f.*

Balance, *s.* तुला, मा[illegible]; ' beam of a b. ' तुलादंडः-यष्टि *f.* 2 [illegible] अवशेषः ' what is the b. against me ' मया देयः (द्रव्य-)शेषः कियान्वर्तते. 3 [illegible]नं; विगणनं, समतोलनं. 4 तुल्यता, [illegible]भारता. **-** *v. t.* तुल् 10 (तुलयति): [illegible] accounts ' समीं कृ 8 U, शुध् c. [illegible] (In thought) विविच् 7 P; विक्लृप् c. **-** *v. i.* दोलायते(D.) **-ed,** *a.* तुलित. 2 तुल्यभार; समीकृत; ' b. sheet ', *s.* संक्षिप्तगण[illegible]लेखः, देयादेयशेषदर्शकं गणनापत्रकं.

Balcony, *s.* वरंडः, प्रग्रीवः, वितर्दि-र्दी *f.*

Bald, *a.* वि-अ-केश (शी *f.*), मुंड, खलति. 2 अनावृत, नग्न, असंस्कृत. 3 असभ्य, अशिष्ट, अलंकारहीन.

Baldrick, *s.* मेखला, कांची, रस(श)ना. 2 राशिमंडलं, ज्योतिश्चक्रं.

Bale, *s.* भांडं, भारः; द्रव्यपोटलिका. 2 क्लेशः, विनाशः. **-** *v. t.* जलं उत्क्षिप् 6 P. **-ful,** *a.* सशोक, क्लेशार्त, दुःखित. 2 प्राणहर (री *f.*), विनाशिन्, *See* **Deadly.**

Balk, *v. t. See* **Baffle.** **-** *s.* सेतुः, सेतुबंधः.

Ball, *s.* कंदुकः (for playing); गोलः-लं, वर्तुलं, मंडलं; ' eye b. ' तारा. 2 नृत्यक्रीडा, ' b. room ' नृत्यस्थानं.

Ballad, *s.* गीतं, गीति *f.*, गानं; ' b. singer ' गायकः.

Ballast, *s.* पोतस्थैर्यद्रव्यं.

Balloon, *s.* विमानं, आकाश-व्योम-यानं.

Ballot, *s.* गुटि(लि)का.

Balm, *s.* गुग्गुलः, वृक्षनिर्यासः. 2 प्रशमः, शांतिः *f.* **-y,** *a.* सुरभि. 2 तापहर (री *f.*), शांतिद, उपशमक.

Balsam, *s.* विलेपनं, अभ्यंजनं. **-ic,** *a.* स्निग्ध, चिक्कण.

Baluster, *s.* लघुस्तंभः.

Balustrade, *s.* लघुस्तंभपंक्ति *f.*

Bamboo, *s.* वेणुः, वंशः, कीचकः (sounding b.).

Bamboozle, *See* **Cheat.**

Ban, *s.* घोषणं. 2 अभिशापः, आक्रोशः. 3 नि-प्रति-षेधः. **-** *v. t.* अभिशप् 1 U, प्रतिषिध् 1 P.

Banal, *a.* क्षुद्र, लघु, तुच्छ.

Banana, *s.* कदली, तृणसारा, गुच्छफला.

Band, *s.* बंधः, पाशः, बंधनं 2 समूहः, श्रेणी. 3 दलं, गुल्मः-ल्मं (of troops). 4 तूर्यसमूहः, वादित्रगणः. **-** *v.* संमिल् 6 P, संयुज् 10 *See* **Assemble.**

Bandage, *s.* बंधः, बंधनं, पट्टः, आवेष्टनं.

Bandit, *s.* दस्युः, चोरः, स्तेनः.

Bandy, *v. t.* इतस्ततो विक्षिप् 6 P. 2 विनिमे 1 A; ' b. words ' वाचा उत्तरं दा 3 U. **-legged,** *a.* प्रज्ञु, प्रगतजानु. **-** *s.* वक्राग्रयष्टि *f.*

Bane, *s.* गरः-रं, विषं. 2 (fig.) नाश-अनर्थ-मूलं, क्षयकारणं, विनाशहेतुः, आधिः; वामाः कुलस्याधयः (*S.* 4.) ' are a b. to the family. ' **-ful,** *a.* विषान्वित, सविष, विनाशिन्, विनाशन.

Bang, *v. t.* प्रहृ 1 P, तड् 10, अभि-प्रति-हन् 2 P. **-** *s.* आघातः, प्रहारः, कराघातः.

Bangle, *s.* वलयः-यं, कंकणं.

Banion, *See* ' **Banyan.** '

Banish, *v. t.* वि-निर्-वस् c., प्रव्रज् c. 2 निराकृ 8 U, निः-उत्-सृ c., अपानुद् 6 P, निरस् 4 P; ' the thought was b. ed from his mind ' सा चिंता मनसो निरस्ता. **-ment**

s. विवासनं, निर्वासनं, प्रव्रा(व्र)जनं. 2 निराकरणं, निरसनं.

Bank, s. तीरं, कूलं, तट-टी, रोधस् n., कच्छः; 'the other b.' पारं; 'sand b.' सैकतं. 2 धनागारं. —v. t. कूलेन परिवेष्ट् 1 A or c. **-er**, s. धनागारपतिः; श्रेष्ठिन् m., कुसीदिकः.

Bankrupt, s. ऋणदान-ऋणशोधन-अक्षमः, सर्वस्वच्युतः, परिक्षीणः, निर्धनः. **-cy**, s. परिक्षीणता, ऋणशोधनाक्षमता, &c.

Banner, s. ध्वजः, पताका, केतनं, वैजयंती, केतुः.

Banns, s. विवाहघोषणा.

Banquet, s. विशिष्टभोजनं, स्वाद्वन्नभोजनं. —v. t. मिष्टान्नैः भुज् c. or संतुष् c. —v. i. विशिष्टान्नं भुज् 7 A or भक्ष् 10; 'the horses were b. ing upon the grass' अश्वास्तृणं यथेष्टं भक्षयंत आसत.

Banter, v. t. भर्त्स् 10 A, निंद् 1 P, अधिक्षिप् 6 P. 2 अव-वि-उप-हस् 1 P. —s. निंदा, अधिक्षेपः, अवहासः, &c.

Bantling, s. *See* **Baby**.

Banyan, s. वटः, न्यग्रोधः.

Bar, s. अर्गलं-ला, अर्गलाबंधः. 2 प्रत्यूहः, अंतरायः. 3 शलाका (of a cage). 4 दंडः; 'iron b.' लोहदंडः, लोहपिंडः. 5 सैकतं. 6 न्यायसभा. —v. t. नि-प्रति-रुध् 7 U, नि-प्रति-षिध् 1 P. निराकृ 8 U. निरस् 4 P, निवृ c. or निवार् 10. 2 अर्गलेन बंध् 9 P.

Barb, s. कर्णः, शूलाग्रं. 2 अश्वतनुत्रं. **-ed**, a. कर्णिन्

Barbarian, s. ग्राम्यः, असभ्यः. 2 म्लेच्छः; यवनः, किरातः. 3 विदेशिन् m., वैदेशिकः.

Barbarous, a. वैदेशिक (की f.). 2 अशिष्ट, असभ्य, अश्लील. 3 निष्ठुर, क्रूर, निर्दय. **-ly**, adv. क्रूरं, निष्ठुरं, निर्दयं, श्वापदवत्, पशुवत्. **-Barbarity**, s. निष्ठुरता, नृशंसता, क्रौर्यं, असभ्यता, अशिष्टता.

Barber, s. नापितः, क्षौरिकः, क्षुरिन् m.; 'b.'s wife' नापिती; 'b.'s business' नापित्यं.

Bard, s. वंदिन् m., वैतालिकः.

Bare, a. अनावृत. शून्य. 2 केवल, मात्र in comp.; 'on the b. ground' अनवधानायां भूमावेव (Ka. 151). 3 विवस्त्र; 'b. footed' पादुकाहीन, अनावृतपाद; 'b. headed' अनावृतशिरस्; 'b. faced' निर्लज्ज, धृष्ट; 'thread b.' (clothes) जीर्णानि वासांसि. —v. t. नग्नीकृ 8 U, विवस्त्रीकृ; उच्छद् 10. 2 उत्कुष् 1 P. **-ly**, adv. मात्रं, केवलं. 2 कथमपि, कष्टेन, कृच्छ्रेण. **-ness**, s. शून्यता, विवस्त्रता. 2 क्षीणता, दैन्यं.

Bargain, s. संविद् f., समयः, अभ्युपगमः; 'a b. was struck' इति समयः कृतः; 'buy the horse, it is a good b.' स्तोकमूल्येन लभ्यतेयमश्वः क्रीणीहि तावदेनं; 'in the b.' अपि, अपरंच, 2 पणः, विपणः, क्रयविक्रयनियमः. —v. t. पण् 1 A, व्यवहृ 1 P.

Barge, s. केलिनौका. 2 तरालः, वहित्रं. **-man**, s. नाविकः, पोतवाहः.

Bark, s. त्वच् f., वल्कं, वल्कलः-लं. 2 पोतः क्षुद्रनौः, तरीः. —v. i. बुक्क् 1 P, 10; 'dogs b. at the moon' श्वानः शशिनं वीक्ष्य बुक्कयंति; भष् 1 P. —v. t. त्वचं-वल्कं-अपनी 1 P or निष्कुष् 1 P. **-ing**, s. बुक्कनं, भषणं. **-y**, a. वाल्कल (ली f.), त्वङ्मय (यी f.).

Barley, s. यवः, प्रवेटः; 'b. broth' यवसुरा-?; 'b. corn' यवः; 'unripe b.' तुस्मार्य; 'b. water' उदमंथः.

Barm, s. सुरा-मद्य-मंडः.

Barn, s. कुसूलः, धान्यागारं, धान्यसंग्रहस्थानं.

Barometer, s. आकाशतोलनयंत्रं.

Barrack, s. सैन्यावासः, सैन्यागारं. —v. t. सैन्यागारे स्था c. (स्थापयति) or निवस् c.

Barrel, s. दीर्घगोलाकारं काष्ठपात्रं. 2 (Of guns) नाडि-डी f., नालि-ली f.

Barren, a. वंध्य (lit. and fig.). 2 व्यर्थ, मोघ, निष्फल. 3 (Ground) अनुर्वर, अशस्यवत्, मरुस्थलं-ली. 4 शून्य, रिक्त. **-ness**, s. वंध्यत्वं. 2 वैयर्थ्यं, शुष्कता.

Barricade, s. प्राकारः, वप्रः-प्रं, प्राचीरं. —v. t. वि-प्रति-रुध् 7 U, *See* **Obstruct**.

Barrier, s. वृति f., वप्रः-प्रं, प्राकारः. 2 सीमन् f., सीमा, पर्यंतः-तं. 3 विघ्नः, प्रत्यूहः, अंतरायः, व्याघातः.

Barrister, s. उत्तरवादिन् m., परार्थे वक्तृ m.; स्मृतिशास्त्रकुशलः.

Barrow, s. शूकरः. 2 उक्षतशूकरः. 3 शकटिका.

Barter, s. विनिमयः, प्रतिदानं, परि(री)वर्तः. —v. t. विनि-मे 1 A, परिवृत् c.; 'b. ed for 5 cows' पञ्चगु (गृहं &c.). —v. i. भांडविनिमयेन वाणिज्यं कृ 8 U, व्यवहृ 1 P.

Base, a. नीच, अनार्य, खल, दुष्ट, कदर्य, जघन्य, अधम, नि-अप-कृष्ट. 2 विजात, हीनजाति, अनभिजात, अकुलीन. 3 कृपण. 4 (Notes) धीर, गंभीर; 'b. metal' कुप्यं. —s. अधोभागः, मूलं, तलं, उपष्टंभः. 2 मूर्धन् m., भूमि f. 3 वास्तु n.; पोटः; 'based on' ex. by मूल in comp.; 'delusion b. ed on ignorance' अज्ञानमूलका भ्रांतिः. **-ly**, adv. नीचतया, अधर्म &c. **-less**, a. निर्मूलक, निराधार, अमूल. **-ness**, s. अधमता, अनार्यता, निकृष्टता; अकुलीनता, वैजात्यं; गांभीर्यं.

Bashful, a. ह्रीमत्, लज्जावत्, सव्रीड, त्रपिन्, सलज्ज, शालीन, सत्रप, विनीत, भीरु. **-ly**, adv. सलज्जं, सत्रपं, सव्रीडं; 'his face b. bent down' लज्जावनतमुखः. त्रपाधोमुखः. **-ness**, s. लज्जा, त्रपा, ह्रीः; व्रीडा, शालीनता, विनयः, भीरुता.

Basil, s. तुलसी, कुठेरकः, पर्णासः.

Basin, *s.* थाली, द्रोणी. 2 जलाशयः, तडागः, कासारः. 3 आलवालं, आधारः, आवापः, आवालं. 4 खातं. 5 सरित्प्रदेशः, रयपथः.

Basis, *s.* मूलं, पीठिका *f.*; आधारः.

Bask, *v. i.* सूर्यातपं नि-आ-सेव् 1 A; 'b. s in the morning sun' बालातपं निषेवते.

Basket, *s.* मंजूषा, पि(पे)टकः, करंडः, कंडोलः. **-maker,** *s.* वैणवः, वैदलकारः. **-work,** *s.* वैदलं.

Bass, *s.* *See* **Base** 4. 2 कटः; 'b. relief' प्रतिच्छाया.

Bastard, *a.*, *s.* जारज, कुंड, कुलटोत्पन्न; कौलटेय, कानीन, विजन्मन्, दासीपुत्रः (त्री *f.*), विजात.

Baste, *v. t.* लगुडेन तड् 10 or ग्रह् 1 P or आहन् 2 U. 2 सिव् 4 P. **-Bastinade,** *s.* लगुडाघातः, गदाप्रहारः, ताडनं.

Bastile, *s.* प्राकारयुक्तं दुर्गं.

Bastion, *s.* वप्रः-प्रं.

Bat, *s.* जतुका, अजिनपत्रा, परोष्णी, तैलपायिका. 2 यष्टि *f.*, गदा, लगुडः.

Batch, *s.* गणः, संघः. समूहः.

Bate, *See* **Abate**.

Bath, *s.* स्नानागारं, स्नानकुंडं, अवगाहनस्थानं.

Bathe, *v. i.* स्ना 2 P. मस्ज् 6 P (loc.); गाह् 1 A, वि-अव-गाह् (with acc.). **-***v. t.* स्ना c. (स्ना-स्न-पयति); प्रक्षल् 10, धाव् 10; अभिषिच् 6 P, निमस्ज् c. (मज्जयति). **-ing,** *s.* स्नानं, निमज्जनं, अवगाहनं, अभिषेकः. **-***a.* स्नानीय; 'b. cloth' स्नानीयवस्त्रं.

Bathos, *s.* नीचता. 2 गांभीर्यं.

Bating, *prep.* *See* **Except.**

Batlet, *s.* राजकप्रयुक्तः काष्ठमुद्गरः.

Baton, Batoon, *s.* दंडः, गदा, यष्टि *f.*, लगुडः.

Battalion, *s.* गुल्मः-ल्मं, वाहिनी, सैन्यदलं.

Batten, *v. i.* आप्यै 1 A, स्फाय् 1 A; 'the wolf b. s on the lamb' अजा (मांस) भक्षणेनात्मानमाप्याययति; उदरं भृ 3 U. **-***v. t.* प्यै c., सह्वृ c. पीन *a.* कृ 8 U.

Batter, *v. t.* मृद् 9 P, चूर्ण् 10, मंथ् 9 P, निष्पिष् 7 P, प्रभंज् 7 P. **-y,** *s.* मर्दनं, पेषणं. 2 कामानश्रेणी.

Battle, *s.* युद्धं, रणः-णं, समरः, संग्रामः, संघर्षं, प्रधनं, आहवः, आजि *f.* समिति *f.*, युध् *f.*, 'b. array' व्यूहः, सैन्यविन्यासः; 'b. axe' परशुः; 'b. cry' सिंहनादः, क्ष्वेडितं, 'b. field' रण-समर-&c.-भूमि *f.*, रणांगणं. **-***v. i.* युध् 4 A. **-ment,** *s.* सच्छिद्रः प्राकारः, भित्ति *f.*

Battue, *s.* संकुलवधः-निषूदनं.

Bauble, *s.* अल्पमूल्यं आभरणं, अल्पार्थं क्रीडनकं.

Bawd, *s.* कुट्टिनी, दूती, शंभली. **-ry,** *s.* दूतीकार्यं; कुट्टिनीकर्मन् *n.* **-y,** *a.* गर्हित, अशुद्ध, अविनीत, नीच, 'bawd-house' वेश्याश्रमः, वेशः.

Bawl, *v. i.* आ-उत्-क्रुश् 1 P, उच्चैः-तारस्वरेण शब्दायते (D.); रट् 1 P, नद् 1 P, उद्घुष् 10. **-er,** *s.* आ-उत्-क्रोष्टृ *m.*, उद्घोषकः. **-ing,** *s.* उत्क्रोशः, उद्घोषणं.

Bay, *a.* पिंग, पिंगल. **-***v. i.* *See* **Bark,** **-***s.* खातं, वंकः; 'turn to b.' 'stand at b.' शत्रोरभिमुखः स्था 1 P; 'b. salt.' समुद्रलवणं, सैंधवं.

Bayonet, *s.* निस्त्रिंशः, गुलिकाप्रक्षेपणीसंसक्ता छुरिका.

Bazar, *s.* आपणः-णं, पण्यवीथिका-वीथी, विपणि-णी *f.*, हट्टः, निषद्या.

Be, *v. i.* भू 1 P, अस् 2 P, वृत् 1 A, विद् 4 A; 'b. it so' भवतु, एवं-तथा-अस्तु. **-Being,** *s.* भावः, अवस्था, वृत्ति *f.*, अस्तित्वं, सत्ता. 2 भूतं, सत्वः-त्वं; 'rational b.' सचेतनः, प्राणिन् *m.*; 'corporal b.' शरीरिन् *m.*, देहिन् *m.*; 'Supreme B.' परमेश्वरः, परमात्मन् *m.* 2 जन्मन् *n.*, संभवः, उत्पत्ति *f.* **-***a.* सत्, वर्तमान : 'b. that' यतः, यस्मात्; ex. by abl. or instr. of nouns.

Beach, *s.* (समुद्र-) तीरं, कूलं, वेला, तटं-टी. **-y.** *a.* तटयुक्त, कूलमय (यी *f.*).

Beacon, *s.* आकाशदीपः, महोल्का.

Bead, *s.* गुली, गुलिका; 'a string of b. s' माला; हारः; 'a rosary of b. s;' जप-अक्षमाला; 'telling b. s' जपमालां गण् 10. **-man,** *s.* जपकरणे नियुक्तो जनः.

Beadle, *s.* दंडधरः.

Beak, *s.* चंचु *f.*, चंचूः, मुखं, तुंडः-डं. **-ed,** *a.* चंचुमत्, तुंडयुक्त. **-er**, *s.* काचपात्रं.

Beam, *s.* तुला, स्थूणा; 'of a balance' दंडः, यष्टि *f.*; 'of a carriage' धुर् *f.* 2 किरणः, अंशुः; *See* **Ray.** **-***v. i.* प्रोत्-वि-लस् 1 P, स्फुर् 6 P; 'a face b. ing with joy' मुदा विलसदाननं. **-less,** *a.* निष्प्रभ, निस्तेजस्. **-y,** *a.* भास्वत्, भासुर, देदीप्यमान, अंशुमत्.

Bean, *s.* माषः, शिंबिकः.

Bear, *v. t.* वह् 1 P, नी 1 P. 2 धृ 1 P, आलंब् 1 A, भृ 3 U (राज्यभारमुवाह-बभार). 3 सह् 1 A, मृष् 4 P, 10, क्षम् 1 A. 4 प्रसू 2 A; उत्पद् c., जन् c. (जनयति); 'Satyavati bore two sons to the king' नृपेण सत्यवत्यां पुत्रौ जातौ,-उत्पादितौ, नृपः सत्यवत्यां पुत्रावजीजनत्; the same sense ex. in स नैषधस्य सुतायां पुत्रमुत्पादयामास (R. xviii. 1) 'he had a son by the daughter' &c. 5 (Cherish) भृ 3 U, धृ 1 P; 'I b. no malice to you' त्वय्युपरि द्वेषं न धारयामि, or न त्वं मम द्वेषपात्रं-स्थानं; 'he bore himself bravely on the occasion' तस्मिन्नवसरे तेन साधु आचरितं, धीरं विक्रान्तं; 'b. witness' साक्ष्यं दा 3 P

(with gen.) ; ' b. company ' सहचरः (री *f.*) भू 1 P; ' b. name ' नाम भृ 3 U, or भृ 10; व्यपदेशं भज् 1 A; (एवंव्यपदेशभाजिनः U. 6); ' b. fruit ' सफलीभू, फल् 1 P; ' b. in mind ' चित्ते अवधृ 10, मनसि कृ, अनुस्मृ 1 P, -*s.* ऋक्षः, भल्लूकः, भालुकः. -**Born,** *a.* जात, उत्पन्न, प्रसूत, संभूत; ' to be b. ' जन् 4 A. उत्पद् 4 A; प्रसू pass., उद्भू 1 P, संभू; 'was b. in the form of a dwarf' वामनरूपेण जातः-अवतीर्णः. -**back,** *v. i.* परा-प्रति-नि-वृत् 1 A. -**down,** *v. t.* अपाकृ 8 U; पराजि 1 A, निपत् c.; ' bore down all opposition' सर्वमंतरायमपाकुर्वन्. -**on,** *v. i. See* **Apply.** -**out** *v. t.* (fig.) द्रढयति (D.): समर्थ् 10. -**up,** *v.* उद्वह् c., उत्तंभ् c., as in झटिति घटनोत्तंभितमिव (U.3). **2** सह् 1 A; 'b. under grief' दुःखप्रतिकारं कुरु, शोकवशं मा गमः. -**er,** *s.* वाहः, हरः, वाहकः, in comp. वार्ताहरः ' b. of news ' -**ing,** *s.* अवस्थानं, स्थिति *f.* **2** वृत्ति *f.* वर्तनं, आचरणं, रीति *f.*

Beard, *s.* श्मश्रु *n.*, कूर्चं; मुखरोमन् *n.*; ' wearing long b. ' दीर्घकूर्चाः (pl.). **2** शूकं, किंशारुः. **3** फलं, कणः. -*v. t.* न्यक्कृ 8 U, समक्षं अवज्ञा 9 U or निर्भर्त्स् 10 A or अधिक्षिप् 6 P. -**ed,** *a* सश्मश्रु; श्मश्रुल, कूर्चधर &c. -**less,** *a.* श्मश्रुहीन;अजात-अनुद्भिन्न-श्मश्रु. **2** अप्रगल्भव्यवहार.

Beast, *s.* पशुः, मृगः, जंतुः ; ' b. of prey ' श्वापदः; ' b. of burden ' धुर्यः, धुरीणः ; ' b. in the form of man ' नरपशुः. -**ial,** -**ly,** *a.* पशुतुल्य, जघन्य, पशुशील.

Beat, *s.* आघातः, प्रहारः ; ताडनं. **2** स्पंदनं, स्फुरणं. -*v. t.* तड् 10. प्रह् 1 P, तुद् 6 P, अभिहन् 2 P, आहन् 2 A, (आहतायां मयाणभेर्यां). 2 (defeat) विध्वंस् c., भंज् 7 P, पराजि 1 A, पराभू 1 U. **3** आलुड् c., चूर्ण् 10. -*v. i.* स्पंद्-कंप्-वेप् 1 A, स्फुर् 6 P: ' b. very fast ' धमधमायते (D.). -**down,** निपत् c.; (price) न्यूनीकृ. -**into,** ताडनेन कृ or निर्मा 3 A: ' I shall b. thee into a good boy ' ताडयित्वा ताडयित्वा त्वामहं विद्वांसं करिष्यामि. -**off,** विद्रु c., प्रतिहन्. -**about the bush,** (lit.) वनं ग्रह् 9 P or आलुड् 10; (fig.) अप्रस्तुतमालप् 1 P. *See* **Bush.**

Beatify, *v. t.* परमानंदं दा 3 U. **2** अमरेषु गण् 10, स्वर्गीयलोकमध्ये आरुह् c. -**ic,** *a.* अपवर्गद, मोक्षप्रद.

Beatitude, *s.* मोक्षः, मुक्ति *f.*, निःश्रेयसं, अपवर्गः, निर्वाणं, परमा गतिः, कैवल्यं, ' desirous of b. ' मुमुक्षुः.

Beau, *s.* सुवेषः, शुभाननः.

Beauty, *s.* सौंदर्यं, सुरूपता, लावण्यं, शोभा, कांति *f.*, रूपं, रमणीयता, अभिरूपता,मनोज्ञत्वं, श्रीः, लक्ष्मीः. -**Beautify,** *v. t.* भूष् c., भूष् 10, अलंकृ 8 U. -**Beautiful, Beauteous,** *a.* सुंदर (री *f.*), रम्य, रमणीय, कांत, मनोज्ञ, सुरूप, लावण्यवत्, रुचिर, शोभन, चारु (र्वी *f.*), मंजुल oft., by सु in comp.; सुमुखं-सुस्थलं. -**ly,** *adv.* साधु, सुंदरं, सुष्ठु, सु in comps.

Beaver, *s.* शिरस्त्राणभागः.

Becalm, *v. t.* निर्वात *a.* कृ 8 U, प्रशम् c. (शमयति); *See* **Calm.**

Because, *conj* इति, हि (not at the beginning of a statement). यतः, यत्; more oft. ex. by कुतः, कस्मात् with abl.; by abl. or instr.; ' b. he is liable to the charge of inequality and cruelty ' (नेश्वरो जगतः कारणमुपपद्यते) कुतः वैषम्यनैर्घृण्यप्रसंगात् ' b of ex. by instr. or abl.; हेतोः, कारणात्; ' b. of this ' इति हेतोः.

Beck, *s.* संज्ञा; संकेतः. -**on,** *v. t.* शिरसा-हस्तेन संज्ञां-संकेतं दा 3 U. **2** संज्ञया आह्वे 1 P.

Become, *v. i.* भू 1 P, संपद् 4 A; वृत् 1 A, जन् 4 A; in majority of adjectives ex. by nouns with गम्, प्राप् &c. ' became dejected' विषादं गतः, विषादमभूत्; 'b. a hated ' द्वेष्यतां याति; became amazed' विस्मयमापेदे; ' b. in curious ' समुपजातकुतूहलः; ' what he one of the queen Sita ' सीतादेव्याः किं वृत्तं (U. 2), किमभवत्.-*v. t.* युज् pass., उपपद् 4 A,(with loc.); gen. ex. by अनुरूप, सदृश (शी *f.*), उचित, उपपन्न (all with gen.); ' does this b. thy matted hair ' किमिदं जटानामनुरूपं, युक्त-सदृशं &c. -**ing,** *a.* उचित, अनुरूप, युक्त, उपपन्न. ' it is b. ' सांप्रतं.-**ingly,** *adv.* यथोचितं, यथार्हं, युक्तं, अनुरूपं.

Bed, *s.* शय्या, शयनं, तल्पः-ल्पं, संस्तरः, शयनीयं;' leave the b. ' मुंच शयनं; confined to b. ' ' b. rid ' शय्यागत, शय्याग्रस्त ; ' polluter of other's b. ' पारतल्पिकः, परतल्पगः ; ' go to b. ' स्वप् 2 P, शी 2 A; ' b. chamber, ' ' b. room ' शयनागारं, शयनगृहं, वासगृहं ; ' b. clothes ' शय्योपस्कराः ; ' b. sheet ' शयनास्तरणं, उत्तरच्छदः; ' b. stead ' पर्यंकः, खट्वा, मंचः.**2** (of a river) मध्यं, स्रयपथः. **3** फलकः. -**Bedding,** *s.* शय्योपकरणं, शयनसामग्री.

Bedash, Bedraggle, *See* **Stain.**

Bedaub, *See* **Daub.**

Bedeck, *v. t.* विभूष् 10. *See* **Adorn.**

Bedew, *v. t.* आर्द्रीकृ 8 U, क्लिद् c., प्रोक्ष् 1 P, सिच् 6 P.

Bedim, *v. t.* मलिनीकृ 8 U, कलुषीकृ; 'eyes b. ed with tears' बाष्पप्रकरकलुषां दृष्टिं (S. 6).
Bedizen, *v. t.* परिष्कृ 8 U. *See* **Adorn.**
Bedlam, *s.* उन्मत्तानां निवासः, वातुलालयः. -*a.*, **-ite,** उन्मत्त, वातुल.
Bee, *s.* अलिः, भ्रमरः, द्विरेफः, शिलीमुखः, भृंगः, मधुकरः, षट्पदः; 'honey b.' सरघा, मधुमक्षिका; 'b. hive' मधुकोषः; 'bees wax' मधुजं, शिक्थं.
Beef, *s.* गोमांसं.
Beer, *s.* यवसुरा-रं, यवमद्यं.
Beetle, *s.* पिंगकपिशा. **2** मुद्गरः. -*v. i.* *See* **Jut.**
Befall, *v. t.* आ-समा-पत् 1 P; 'such incidents b. worldly persons' आपतंति हि संसारपथमवतीर्णानामेते वृत्तांताः (Ka. 175) उपस्था 1 U, उपनम् 1 P (with gen.) कस्यात्यंतं सुखमुपनतं दुःखमेकांततो वा (Me. 109) संपद् 4 A, घट् 1 A.
Befit, *v. t.* Become.
Befool, *v. t.* व्यामुह् c. विभ्रम् c. (भ्रमयति).
Before, *prep.* (Time) प्राक्, पूर्वं, अर्वाक्, (with abl.). **2** (Place) पुरः, पुरतः, अग्रे, अग्रतः, पुरस्तात् (with gen.); समक्षं, साक्षात्, प्रत्यक्षं. -*adv.* (place) *See* above. **2** (Time) पूर्व in comp.; 'not heard b.' अश्रुतपूर्व. -*conj.* यावत् न-तावत्; 'study your lesson b. he comes' यावदसौ नागच्छति तावत्पाठमधीष्व; एकस्य दुःखस्य न यावदंतं गच्छामि तावद्द्वितीयं समुपस्थितं मे; 'b. hand' प्रागेव, पूर्वमेव; प्रथममेव, अग्रे; 'b. mentioned' पूर्वोक्त, प्रागुक्त; 'as b.' यथा पुरा, यथापूर्वं; पूर्ववत्, 'in times gone b.' पुरा, गतकाले.
Befoul, *v. t.* दुष् c. (दूषयति); *See* **Stain.**
Befriend, *v. t.* अनुग्रह् 9 P; उपकृ 8 U, साहाय्यं कृ (with gen.),
Beg, *v. i.* भिक्ष् 1 A, भिक्षाटनं कृ 8 U, भिक्षां याच् 1 A. -*v. t.* अंजलिं बद्ध्वा-पादयोः पतित्वा विज्ञा c (ज्ञापयति) or निविद् c. **2** याच् 1 A; अभि-प्र-अर्थ् 10 A; 'b. s. to say' विज्ञापयति; 'b. favour of' प्रसद् c., अनुनी 1 P. **-ging,** *s.* याच्ञा, प्रार्थना. **2** भिक्षा, भिक्षाटनं. **-Beggar,** *v. t.* दरिद्री कृ 8 U सर्वस्वं हृ 1 P; 'b. s description' वर्णनातीत. *s.* -प्रार्थकः, अर्थिन् *m.*, भिक्षुः, याचकः, दरिद्रः. **-ly,** *a.* निर्धन, कृपण. **2** नीच, अपकृष्ट. **-y,** *s.* दैन्यं, कार्पण्यं, दारिद्र्यं, भैक्ष्यं.
Beget, *v. t.* जन् c. (जनयति); उत्पद् c.; प्रसू 2 A, सृज् 6 P. **-ter,** *s.* जनकः, उत्पादकः, जनयितृ *m.*
Begin, *v. t.* आ-प्रा-रभ् 1 A; प्र-उप-क्रम् 1 A, प्रस्तु 2 U, (प्रस्तूयतां भोः), प्रवृत् 1 A; 'the wind began' वातोप्रसरोद्भूत. **-ner,** *s.* आरब्धृ *m.*, नवच्छात्रः. **-ning,** *s.* आरंभः, उपक्रमः. **2** आदि *m.*; 'having no b.' अनादि. **3** मूलं, योनि *f.*, प्रभवः; 'b. with' आदि-आद्य- in comp.; 'in the b.' आदौ; 'from the b.' आमूलात्, आदितः; 'God has neither b. nor end' अनाद्यनंत ईश्वरः.
Begird, *v. t.* परिवेष्ट् 1 A or c., अवरुध् 7U, आ-परि-वृ 5 U; वलय, रसना, in comp.; समुद्ररसना-उदधिवलया-पृथ्वी 'earth begirt by sea'.
Begone, *interj.* अपेहि, अपसर, अपयाहि.
Begrease, *v. t.* वसया लिप् 6 P, or स्निग्धीकृ 8 U.
Begrime, *See* **Soil.**
Begrudge, *See* **Envy,** *v. t.*
Beguile, *v. t.* विलुभ् c., अतिवह् c. (of time) (कथाभिर्दिवसमत्यवाहयत्). **2** व्यामुह् c., वंच् 10, विप्रलभ् 1 A, आकृष् 1 P; प्र-वि-लुभ् c.
Behalf, (on or in) अर्थे, अर्थं, हेतोः, कारणात्, कृते (with gen).
Behave, *v. i.* आचर् 1 P, वृत् 1 A, व्यवहृ 1 P; *See* **Act. 2** वृत्तिं कृ 8 U, अनुष्ठा 1 P; 'well b. ed' सदाचारः. **-Behaviour,** *s.* आचारः, वृत्ति *f.*, व्यवहारः, चेष्टितं, चरितं, आचरणं.
Behead, *v. t.* शिरः (*n.*) छिद् 7 P or कृत् 6 P. **-ing,** *s.* शिरच्छेदः; 'worthy of b.' शीर्षच्छेद्यः.
Behest, *See* **Command** (*s.*)
Behind, *prep.* पश्चात्, पृष्ठतः, (with gen.) अनु (with acc.); 'concealing his body b. the creepers' लतांतरित-लताव्यवहितविग्रहः; 'he is far b. (backward)' मंदः, मंदधीः; 'b. the scenes' नेपथ्ये. -*adv.* पृष्ठतः; 'from b.' पश्चादेत्य, पृष्ठेनागत्य **2** अवरतः, अधस्तात्. **3** दूरे, दूरतः; 'b. part' पश्चाद्देशः, पृष्ठं, नितंबः.
Behold, *v. t.* दृश् 1 P, ईक्ष् 1 A; *See* **See.** **-en,** *a.* उपकृत. कृतोपकारेण पराधीन. **-er,** *s.* प्रेक्षकः, दर्शकः, द्रष्टृ *m.*
Behoof, *s.* अर्थः, फलं, वृद्धि *f.*, लाभः.
Behove, *v. t.* Ex. by pot. pass. part. pot. mood, or अर्ह् 1 P; 'it b. s thee to assist me' त्वया मम साहाय्यं कर्तव्यं, साहाय्यं कर्तुमर्हसि &c., *See* **Become,** *v. t.*
Belabour, *v. t.* *See* **Beat.**
Belate, *v. i.* चिराय or चिरय् D.
Belay, *v. t.* प्रति-उप-बंध् 7 U.
Belch, *v. i.* उद्वम् 1 P, उद्गॄ 6 P. **-ing,** *s.* उद्वमनं, उद्गिरणं, उद्गारः.
Beleaguer, *See* **Besiege.**
Belie, *v. t.* असत्यं आरुह् c. (रोपयति), मिथ्याभियोगं कृ 8 U; परि-अप-वद् 1 A

Believe, *v. t.* विश्वस् 2 P, (with loc.), श्रद्धा 3 U (with loc. of person and acc. of thing); प्रति-इ 2 P (with acc.). **2** संभू c., तर्क् 10, मन् 4 A. **-er,** *s.* विश्वासिन् *m.*, श्रद्धालुः, श्रद्धान्वितः. **-Belief,** *s.* विश्वासः, विश्रंभः, प्रत्ययः, **2** श्रद्धा, आस्तिक्यबुद्धि *f.* **3** मति *f.*, बुद्धि *f.*, 'it is my b.' इति मे मतिः or मतं, इत्यहं मन्ये.

Belike, *adv.* अपि नाम, किंस्वित्.

Belittle, *v. t.* लघूकृ 8 U.

Bell, *s.* घंटा; 'small b.' किंकिणी; 'b. metal' कांस्यं, पीतलोहं; 'b. clapper' घंटावादकः.

Belladonna, *s.* कंटकारिका.

Belle, *s.* सुंदरी, रूपवती स्त्री; सुभगंमन्या.

Belles letters, *s.* वाङ्मयं.

Bellicose, *a.* कलहप्रिय,-शील, रणोत्सुक, युयुत्सु.

Belligerent, *a.*, *s.* बद्धसमर; योधनशील, युयुत्सु.

Bellow, *v. i.* नद् 1 P, निनद्, गर्ज् 1P, रस् 1 P, रट् 1 P, नर्द् 1 P. **-ing,** *s.* गर्जित, निनादः, गर्जनं, रसितं.

Bellows, *s.* भस्त्रा, दृति *f.*, भस्त्री, चर्मप्रसेविका.

Belly, *s.* उदरं, जठरं, तुंदं, कुक्षिः; 'b. ache' उदरशूलः-लं; 'b. full' आकंठं; उदरपूरणं (*s.*), 'b. bound' आनद्धः; बद्धोदर; 'b. god' उदरंभरिः, औदरिकः; 'b. worm' क्रिमिः; कृमिः.

Belong, *v. i.* अस् 2 P, विद् 4 A, भू 1 P, with gen.; or by an adj. from noun; 'this book belongs to me' ममेदं पुस्तकं, or मदीयमेतत् पुस्तकं, 'b. ing to spring' वासंतिक (की *f.*); 'b. ing to the king;' राजकीय. **2** संबंध् pass.; 'this does not b. to you' नायं तव व्यापारः.

Beloved, *a.* प्रिय, इष्ट, दयित, वल्लभ; 'b. person' दयितजनः, &c.

Below, *prep.* अधः, अधस्तात्, तले, (with gen.). **2** ऊन in comp. **3** अयोग्य, अनर्ह, अननुरूप, असदृश (शी *f.*;); 'the gods are b. Hari' अनु हरिं सुराः (S. K.). *-adv.* अधः, अधस्तात्; अधोभागेलोके (in hell). **2** नीचै, अवरतः. **3** इह, इह लोके.

Belt, *s.* मेखला, रस(श)ना, कांची. *-v. t* मेखलारूपेण परिवृ 5 U or परिवेष्ट् 1 A.

Bemangle, *See* **Mangle.**

Bemire, *v. t.* पंकेन मलिनयति (D.). or दुष् c. (दूषयति).

Bemoan, *See* **Lament.**

Bench, *s.* पीठं; फलकः; 'b. of justice' धर्मासनं, व्यवहारासनं.

Bend, *v. t.* नम् c. (न-ना-मयति), अव-आ-नम् c. (नमयति), नम्रीकृ 8 U, आवृज् 10, वक्रीकृ, कुञ्च्-, वि-आ°-, 6 P; 'bent under the load of breasts' कुचभारानमिता, स्तनभरेण नम्रतामानीता, स्तनभारेणावर्जिता; 'b. the brow' भ्रूभंगं कृ; he 'bent his mind again to his task' स पुनरपि स्वकार्ये मनोऽभ्यदधात्-प्रबंध-न्यवेशयत्; 'b. to one's will' वशीकृ. *-v. i.* आ-अव-प्र-नम् 1 P, नम्र-लीन- *a.* भू 1 P 'trees b. down under the load of fruits' भवंति नम्रास्तरवः फलागमैः (S. 5) **-Bent,** *a.* आनमित; ना-न-मित, आभुग्न; प्रवण, प्रह्व, आवर्जित; 'b. on' कृतनिश्चय, सुनिश्चय, कृतसंकल्प, विहितप्रतिज्ञ; 'eagerly b. on killing each other' परस्परवधायतौ. *-s.* नति *f.*, वक्रता, जिह्मता **2** वंकः, पुटभेदः. **3** शीलं, वांछा, निश्चयः, प्रवृत्ति *f.*, अभिनिवेशः, **-ing,** *s.* नति *f.*; नमनं, अवनमनं.

Beneath, *prep.*, *adv.* *See* **Below.**

Benedict, *s.* नवोढः, नवपरिणीतः.

Benediction, *s.* आशिस् *f.*, आशीर्वादः; नांदी (in dramas); आशास्य, *f.* धन्यवादः. **2** स्तवः, स्तुति *f.* **-Benedictory,** *a.* मांगलिक (की *f.*); 'b. stanza' नांदीश्लोकः; नांदी.

Benefaction, *s.* उपकारः, उपकृतं, हितं.

Benefactor, *s.* उपकर्तृ *m.*, उपकारिन् *m.*, हितकृत् *m.*, उपकारकः, हित-प्रिय-करः.

Benefice, *s.* धर्मशिक्षकवृत्ति *f.*

Beneficence, *s.* उपकारशीलता, परोपकारः; उपकारः, हितं, दया, कृपा, त्यागिता.

Beneficent, *a.* दान-त्याग-शील, परोकारिन्, उपकारपर. **2** (thing) हितकर (री *f.*), हितकारिन्, हितावह.

Beneficial, *a.* हित, हितावह, उपकारक, लाभजनक; कल्याणकारक, सुखप्रद.

Benefit, *s.* उपकारः, हितं, अनुग्रहः. **2** फलं, लाभः; 'for public b.' जनहितार्थं. *-v. t.* उपकृ 8 U, अनुग्रह् 9 P, हितं कृ, लाभं दा 3 U.

Benevolence, *s.* परहितेच्छा, परोपकारिता, दया, कृपा, उदारता, **-Benevolent,** *a.* हितैषिन्, उपकारपर, परोपकारशील, दयालु, परहितेच्छु. **-ly,** *adv.* परहितेच्छया, कृपया, दयापूर्वं.

Benight, *v. t.* तमसा आच्छद् 10. **-ed,** *a.* तमोवृत, नैशतमसाक्रांत; (fig.) अज्ञानतमोवृत.

Benign, Benignant, *a.* दयालु, प्रेमपर, सदय, सुखप्रद, कृपालु. **-ity,** *s.* दया, प्रीति *f.*, कृपा, अनुग्रहः, दयालुत्वं.

Benison, *s.* आशिस् *f.*, आशीर्वादः.

Benumb, *v. t.* जडयति (D.), जडीकृ 8 U, स्तंभ् 9 P.

Bequeath, *v. t.* मृत्युसमये इच्छापत्रेण दा 3 U or ऋ c. (अर्पयति), or प्रतिपद् c. **-Bequest,** *s.* रिक्थप्रदानं.

Bereave, *v. t.* वियुज् 8 U, वियुज् 10, (with instr. for 'of'); 'b. ed of Madana' मदनेन वियाकृता. 2 अपनी 1 P, भ्रंश् c., 'to be b. ed' परिहा pass., वियुज् pass. **-ed, Bereft**, *a.* रहित, हीन, वियुक्त, शून्य in comp. **-ment**, *s.* इष्टवियोगः, वियोगः, विरहः.

Berry, *s.* कुली, गुटिका.

Berth, *s.* शयनागारं, वासगृहं (नाकायां).

Bescatter, *See* **Scatter**.

Beseech, *v. t.* अनुनी 1 P, प्रसद् c., विनयेन याच् 1 A or प्रार्थ् 10 A. **-er**, *s.* प्रार्थकः, याचकः, आयन् *m.*

Beseem, -ly, *See* **Become**.

Beset, *v. t.* रुध् 7 U, आकुलीकृ 8 U, आक्रम् 1 U, 4 P, संबाध् 1 A, उपपीड् 10, अभिभू 1 P. **-a.** आकुल, अभिभूत; 'b. with difficulties or dangers' सकटाकुल, अनर्थसंबाध, विपदभिभूत.

Beshrew, *v. t.* अमंगल प्रार्थ् 10 A, शप् 1 A.

Beside, *prep.* पार्श्वे, समीपे -पे; अभितः, परितः (acc.); निकटे-टे (gen). 2 अतंभद् *a.*; 'b. oneself with joy' आनंदपरवशः, आनंदेन विगतचेतन इव भूत्वा; 'this is b. the question' अप्रास्ताविकं-अप्रासंगिकं-एतद्, अप्रकृतं.

Besides, *prep.* Ex. by भिन्न, व्यतिरिक्त, अपर, इतर, in comp., or with abl. **-adv.** अपरंच, अन्यच्च, किंच, अपिच, अधिकं.

Besiege, *v. t.* रुध् 7 U, अव-उप-रुध्, परिवेष्ट् 1 A or c., आक्रम् 1 U, 4 P **-er**, *s.* अव-उप-रोधकः. **-ing**, *s.* उप-अव-रोधः, रोधनं.

Beslave, *v. t.* वशीकृ 8 U, वृष् c. (वृषयति).

Besmear, *a. t.* वि-ओ-अनु-लिप् 6 P, अंज् 7 P. दिह् 2 U. **-ed**, *a.* लिप्त, अक्त, दिग्ध; विषदिग्धः शरः 'b. with poison'; रक्ताक्तः 'b. with blood'.

Besmirch, *v. t.* *See* **Besmear**. 2 मलिनी कृ 8 U.

Besom, *s.* मार्जनी, शोधनी.

Besort, *v.* i. युज् pass., उपपद् 4 A.

Besot, *v. t.* मुह् c., जडीकृ 8 U. **-ted**, *a.* मूढबुद्धि, मूढात्मन्.

Bespangle, *v. t.* नक्षत्राकारपूर्णैः अनुव्यध् 4 P or उप-शुभ् c. or भूष् 10.

Bespatter, *v. t.* मलेन सिच् 6 P, मलिनयति (D.), कलुषयति (D.).

Bespeak, *v. t.* सूच् 10, शुद्ध c., कथ् 10, *See* **Indicate**; आकृतिरेवास्यामानुषत्वमाचष्टे (Ka.132) 'b. s its being superhuman.,

Bespeckle, Besprinkle, *See* **Speckle, Sprinkle**.

Best, *a.* प्रशस्ततम, उत्तम, श्रेष्ठ, परम, वरिष्ठ; 'to the b. of one's capacity or power' यथाशक्ति, यथासामर्थ्यं; 'to the b. of one's belief' यथामति; 'b. of' ex. by रत्न or वर in comp.; स्त्रीरत्नं, मुनिवरः.

Bestain, *See* **Stain**.

Bestead, *v. t.* लाभाय भू 1 P, हिताय कृप् 1 A.

Bestial, *See* under **Beast**.

Bestir, (oneself) चेष्ट् 1 A, यत् 1 A, प्रयुत् 1 A. उद्यमं कृ 8 U, व्यवसो 4 P.

Bestow, *v. t.* दा 1 P, 3 U, प्रदा, प्रतिपद् c., (with dat.) विद् 1 P (with loc.). 2 प्रयुज् 7 A, 10, निक्षिप् 6 P; 'b. ing wealth on proper persons' वित्तस्य पात्रे व्ययः, 'great care seems to be b. ed on this picture' इदमालेख्यं प्रयत्नतः-सुनिपुणं-निर्मितमिति अनुमीयते; 'b. oneself' सेव् 1 A, आस्था 1 A, मनो निविश् c. **-al**, *s.* दानं, प्रतिपादनं. **-er**, *s.* दातृ *m.*, प्रदः in comp.

Bestraught, *a.* व्यग्र, चिंताकुल; *See* **Anxious**.

Bestrew, *v. t.* आस्तृ-स्तृ 5-9 U.

Bestride, *v. t.* पादौ पृथक् कृत्वा आ-अधिरुह् 1 P or अधिक्रम् 1 U, 4 P.

Bestud, *v. t.* अनुव्यध् 4 P, खच् 10.

Bet, *s.* पणः, प्रतिज्ञा. **-v. t.** पण् 1 A (with gen. of thing staked); शतस्य पणते (S. K.)

Betake, (oneself to) *v. t.* आश्रि 1 U, अंगीकृ 8 U; अरण्यवासमंगीचकार 'betook himself to forest residence'.

Betel, *s.* (tree) तांबूली, पूगवल्ली, नागवल्ली; 'b. box' तांबूलकरंकः, पूगपात्रं; 'b. nut' पूगं, तांबूलं; 'b. box bearer' तांबूलकरंक-वाहिन्.

Bethink, *v. t.* अनुस्मृ 1 P, विमृश् 6 P; *See* **Think**.

Betide, *v. t.* आपत् 1 P, उपस्था 1 U,(gen.) *See* **Befall**; 'may woe b. him' अनर्थं तस्य भूयात्.

Betimes, *adv.* प्रभाते, प्रातः, प्रत्यूषे. 2 यथासमयं, वेलायां, यथावसरं.

Betise, *n.* मौर्ख्यं, मूढता. 2 मौर्ख्यविलसितं.

Betoken, *v. t.* सूच् 10, ज्ञप् c., *See* **Indicate**.

Betray, *v. t.* शत्रुकरेषु अर्प् c. (अर्पयति), विश्वासघातेन अर्प् c. 2 भिद् 7 U; 'b. ed the secret' रहस्यं बिभेद. 3 Indicate, q.v. 4 वंच् 10, *See* **Cheat**; 'b. themselves' आत्मस्वरूपं प्रकटयंति. **-er**, *s.* विश्वासघातकः, वंचकः.

Betrim, *v. t.* भूष् 10, अलंकृ 8 U.

Betroth, *v. t.* (कन्या) दा 3 U, प्रतिपद् c., प्रतिश्रु 5 P, (dat.). **-al**, *s.* वाग्दानं, वाक्प्रदानं

Betrust, *See* **Entrust.**

Better, *a.* श्रेयस्, अग्रतर, गरीयस्, महत्तर, ज्यायस्; 'b. than' वरं-न; 'better death than disgrace (I prefer death to disgrace)' वरं मृत्युर्न पुनरवमानः. 2 (In health) ex. by विशेषः; 'I am b. to-day' अस्ति मे विशेषोऽद्य (S. 3). *-adv.* वरं, श्रेयः, अग्रतरं, अधिकतरं, अधिकं. 2 (With verbs) ex. by तरां; 'he cooks b. than Ra'ma' रामात्पचतितरां. *-s.* श्रेष्ठता, प्रभुत्वं, धर्षत्वं; 'get the b. of' अभिभू 1 P, अतिरिच् pass., *See* **Excel.** *-v. t.* शुध् c.; कृ with (*a.*). **-Betters,** श्रेष्ठाः (pl.).

Between, Betwixt, *prep.* मध्ये, अभ्यंतरे, अंतरे, मध्यस्थाने; oft. ex. by gen. of nouns; देशयोरंतरं 'distance b. the two countries'; 'b. joy and sorrow (tears)' शोकानंदमध्यवर्तिनी (Ka. 318).

Beverage, *s.* पानं, पेयं, पानीयं; 'b. of the Gods' अमृतं.

Bevy, *s.* गणः, संघः, समवायः.

Bewail, *v. t.* विलप् 1 P, क्रुश् 1 P, *See* **Lament.** **-ing,** *s.* शोकः, विलापः, परिदेवनं.

Beware, *v. i.* सावधान-अप्रमत्त-अवहित *a* भू 1 P; 'b. of your enemies' शत्रुविषये सावधानो भव; 'b. lest you will be seduced by pleasures' सावधानो भव भोगेन्द्रियविषयैः प्रलोभ्येथाः; or तथा प्रयतेथा यथा नाक्षिप्यसे विषयैः (Ka. 109).

Beweep, Bewet, *See* **Weep, Wet.**

Bewilder, *v. t.* आकुलीकृ 8 U, विक्लवीकृ, व्या-सं-मुह् c., संभ्रम् c. (भ्रमयति), जडीकृ. **-ed,** *a.* विक्लव, आकुलीभूत, आ-व्या-कुल, विमूढ, विह्वल, संभ्रांत; 'b. what to do' किंकर्तव्यतामूढः, प्रतिपत्तिमूढः. **-ment,** *s.* संभ्रमः, वैक्लव्यं, संमोहः, व्याकुलत्वं.

Bewitch, *v. t.* मुह् c., सं-वि-परि°, वशीकृ 8 U, मद् c. (मनो मदयति वे Mal. 2); मंत्रेण वशीकृ. 2 मनो हृ or आकृष् 1 P. **-ing,** *a.* मोहन (नी *f.*), हारिन्. **-ment,** *s.* मोहनं, मोहः, वशीकरणं, माया, आकर्षणं.

Bewray, *See* **Betray.**

Beyond, *prep.* परतः (with abl.) अतिक्रम्य, अतीत्य, (with acc.); 'b. the forest is the Kailâsa' तदरण्यमतिक्रम्य कैलासगिरिः (Ka. 121); 'Oh! Change b. belief' अहो विश्वासातिक्रांतो (अविश्वास्यः) दशाविपर्यासः; 'b comprehension' अगम्य, दुर्ज्ञेय, दुर्बोध; 'b. expectations' मनोरथानामभूमिः (S. 7); gen. ex. by अति pr.; अधिकं, 'b. measure' अतिमात्रं; 'b. human power' अतिमानुषं; 'b. this continent' द्वीपांतरे; 'lives b. his means' आयाधिकं व्ययं करोति. *-adv.* दूरे, पारे-रं; 'go or pass b.' अतिक्रम् 1 U, अति-इ 2 P.

Bias, *s.* स्पृहा, अभिलाषः. 2 शीलं, भावः. 3 पक्षपातः, पक्षपातित्वं. 4 लोलत्वं, प्रवर्तनं. *-v. t.* प्रवृत्, c., प्रवृत् 6 P, लोलत् c. 2 स्वाधीकृ 8 U; दुष् c. (दूषयति).

Bibber, *s.* मद्यपायिन् *m.*, सुरापः, मद्यपः.

Bibliography, *s.* पुस्तकविद्या.

Bibliomania, *s.* दुर्लभपुस्तकसंग्रहणोन्मादः or -स्पृहा.

Bibulous, *a.* जलशोषक.

Bicentenary, *a.* द्विशतसांवत्सरिक.

Bicker, *v. i.* कलहं कृ 8 U, विवद् 1 A. वाग्युद्धं कृ. **-ing,** *s.* कलहः, विवादः, कलिः. 2 विवादयः.

Bicycle, *s.* द्विचक्रं वाहनं.

Bid, *v. t.* आ-व्या-दिश् 6 P, आज्ञा c.. (ज्ञापयति). 2 मूल्यं कथ् c. (कथयति) or उद्घुष् 10. 3 निमंत्र् 10 A; 'b. welcome' स्वागतं वद् 1 P, or व्याहृ 1 P; 'b. adieu or farewell' आमंत्र् 10 A, आपृच्छ् 6 A; 'b. defiance' धृष् 5 P, आह्वे 1 A. **-der,** *s.* क्रेतृ *m.* **-ding,** *s.* आज्ञा, आदेशः, शासनं. 2 मूल्यकथापनं, अर्घघोषणा.

Bide, *v. t.* स्था 1 P, वृत् 1 A. *-v. t.* प्रतीक्ष् 1 A. 2 सह् 1 A.

Bidental, *a.* द्विदत्, द्विदन्त.

Biennial, *a.* द्विवार्षिक (की *f.*), द्विवर्षिन्, द्वैवर्षिक.

Bier, *s.* शवयानं, कटः, खाट: -टी.

Bifold, *a.* द्विगुण, द्वैध (धी *f.*).

Biformed, *a.* द्विरूप.

Bifurcate, *v. t.* द्विधा कृ 8 U, विभिद् 7 P or c. **-ed,** *a.* द्विधा. 2 विभेदित, द्विधा कृत.

Big, *a.* महाकाय, बृहत्काय (of animate creatures); महाप्रमाण, अतिप्रमाण, स्थूल, विपुल, बृहत्, पृथु (थुः, थ्वी *f.*). 2 **Pregnant** q. v. 3 संकुल, पूर्ण, संकीर्ण; आकीर्ण; 'as b. as' परिमाण, परिमित, मात्र, in comp; बिल्वमात्र 'b. as Bilwa.' **-ness,** *s.* स्थूलता, वैपुल्यं &c. 2 परिमाणं, प्रमाणं.

Bigamy, *s.* (एककाले) द्विपत्नीकरणं; द्विभर्तृकरणं. **-ist,** *s.* द्विपत्नीकः; द्विभर्तृका.

Bight, *s.* अ(आ)खातं.

Bigotry, *s.* स्वमतासक्ति *f.*, स्वमताग्रहः. सनिर्बंधं स्वमतालंबनं. **-Bigoted,** *a.* **Bigot,** *s.* निर्बंधशील, (अविचार्य) स्वमतरक्षिन्, निर्बंधेन स्वमतावलंबिन्.

Bijou, *s.* क्षुद्र-अलंकारः-भूषणं.

Bilbo, *See* **Sword.**

Bile, *s.* पित्तं, मायुः. **-ous,** पैत्तिक (की *f.*), मायुमय (यी *f.*).

Bilingual, *a.* द्विभाषाभाषिन्.

Bilinguous, *a.* द्विजिह्व.

Bilk, *See* **Cheat.**

Bill, *s.* पत्रं, लेख्यं. 2 चंचु (-चू) *f.*, तुंडं. 3 व्ययपत्रं, लेखकः. -*v. t.* *See* **Kiss**, or **Embrace** 'b. of fare,' भोजनवस्तुपत्रिका.

Billet, *s.* पत्रं, लेखः, लेख्यं. 2 काष्ठखंडं. -*v. t.* सैन्यानि वस् c.

Billion, *s.* खर्वः.

Billow, *s.* महोर्मि *f.*, कल्लोलः, तरंगः. -*v. i.* तरंगायते (D.). **-y**, *a.* कल्लोलमालाकुल, प्रचलदूर्मिमालाकुल, तरंगित.

Bimetallic, *a.* द्विधातुक, द्विधातुमय.

Bin, *s.* कुसूलः, धान्यकोष्ठः.

Binary, *a.* द्विगुण, द्वैध (धी *f.*).

Bind, *v. t.* बंध् 9 P, (lit. and fig.); नि-सं-यम् 1 P; 'bound by affection' स्नेहनिबद्धः; नियंत्र् 10; 'I am not bound by these rules' नाहमेभिर्विधिभिर्नियंत्रितोस्मि. 2 आनह् 4 P, पिनह्; 'b. together' सं-बंध्, संश्लिष् c.; ग्रंथ् 9 P, संह् 1 P, संयुज् 7 U, 10; 'b. oneself' प्रतिज्ञा 9 U, प्रतिश्रु 5 P; 'b. by oath' शप् c.; 'b. on' ex. by pot. pass., part., or अर्ह् 1 P; 'the protection of your wife is b. ing on you' त्वया भार्यापोषणमवश्यमेव कर्तव्यं. **-ing**, *s.* बंधः, बंधनं, वेष्टनं, पट्टः, आवरणं. **-Bound**, *a.* बद्ध, निबद्ध, संयत, नियंत्रित, आनद्ध; 'you are b. to obey my orders' त्वया ममाज्ञा अनुष्ठेया इव, आदेशानुष्ठानमर्हसि; 'where are you b., कुत्र गंतुं कृतनिश्चयोसि-कुत्र गंतुकामोसि.

Binocular, *a.* द्विनेत्र, द्विनयन.

Biography, *s.* चरितं, जीवनवृत्तांतः **-er**, *s.* वृत्तांतलेखकः-आख्यातृ *m.*, चरितनिवेदकः

Biology, *s.* प्राणिशास्त्रं.

Bipartition, *s.* द्विधाकरणं.

Biped, *s.* द्विपाद् *m.*, or द्विपदः.

Biplane, *s.* द्विपृष्ठं विमानं or आकाशयानं.

Birch, *s.* भूर्जः, मृदुत्वचः, प्रतिविषा.**-en**, *a.* भूर्जमय (यी *f.*), भूर्जनिर्मित.

Bird, *s.* विहगः, विहंगः,-गमः, पक्षिन् *m.*, खगः, शकुंतः, पतत्रिन् *m.*, गरुत्मत् *m.*, द्विजः, पत्रिन् *m.*, शकुंतिः, अंडजः, पतंगः, शकुनिः; 'bird's eye-view' उच्चस्थानादालोदनं, स्थूलदर्शनं, असूक्ष्मदृष्टिः.

Birth, *s.* जन्मन् *n.*, उद्भवः, संभवः, उत्पत्ति *f.*, जनि *f.*, उत्पादनं, प्रसूति *f.*; 'rich from his b.' गर्भेश्वरः; 'high or noble b.' कुलं, कुलीनता, अभिजातता, अभिजनः, कुले जन्म. 2 वंशः, कुलं, अन्वयः. 3 योनि *f.*, मूलं; 'pride of b.' कुलाभिमानः; 'blind from b.' जात्यंध, जन्मांध, जन्मांध. **-day**, *s.* जन्मदिवसः-दिनं. **-place**, *s.* जन्मस्थानं-भूमि *f.* **-right**, *s.* जन्मतो लब्धोधिकारः; पैतृकं स्वत्वं.

Biscuit, *s.* अपूपः, पिष्टकः, पूपः.

Bisect, *v. t.* समांशद्वयेन विभज् 10U, द्विखंडीकृ 8 U, द्विधा छिद् 7 P.

Bishop, *s.* धर्माध्यक्षः. **-ric**, *a.* धर्माधिकारः.

Bison, *s.* वनवृषभः.

Bit, *s.* खलीनः-नं, कविका. 2 खंडः, लवः, भागः; 'not a b.' न मनागपि, न स्तोकांशेनापि; लेशः (क्रियायाः लेशमात्रस्यापि अनुष्ठानम् इह नोपपद्यते S. B. 74). 3 पिंडः, ग्रासः. -*v. t.* खलीनेन नियंत्र् 10.

Bitch, *s.* शुनी, कुक्कुरी, सरमा.

Bite, *v. t.* दंश् 1 P; 'bit off a large piece' दंतैर्महांतं खंडं खादितवान्-चर्वितवान्; उत्पट् 10, चर्व् 1 P, खाद् 1 P. 2 तीव्रेण पीड् 10. 3 अधिक्षिप् 6 P, *See* **Censure**. 4 पीड् 10, अर्द् 1 P, 10. -*s.* दंशः, दंशनं. 2 दंतक्षतं, दंशनांकः.**-ing**, *s.* दंशनं; 'b. of conscience' मनसोनुतापः. -*a.* दंशक. 2 पीडाकर (री *f.*).

Bitter, *a.* कटु, तिक्त. 2 (Touching) मर्मभिद्-छिद्. 3 उग्र, निष्ठुर, परुष, तीक्ष्ण, कठोर. **-ly**, *adv.* निष्ठुरं, परुषं. 2 अत्यंतं. 3 मन्युकंठं (weeping b.). **-ness**, *s.* कटुता, तिक्तता, तीक्ष्णता. 2 दुःखातिरेकः, उग्रशोकः; 'in b. of soul' दुर्मनायमानचित्त *a.*, समन्युना चेतसा. 3 कठोरता, परुषता, निष्ठुरता. 4 मात्सर्यं, वैशुन्यं.

Bitumen, *s.* शिलाजतु *n.*, गिरिपुष्पकं, शैलेयं, गिरिजं, अश्मजं, अर्घ्यं.

Bivalve, *a.* द्विकोष.

Bizarre, *a.* *See* **Grotesque**.

Blab, *v. i.* रहस्यं भिद् 7 P. **-ber**, *s.* रहस्यभेदकः.

Black, *a.* कृष्ण, श्याम, कृष्णवर्ण, काल. 2 निष्प्रभ, तिमिर, असित, नील, मेचक. 3 (fig.) निंद्य, घोर, दारुण; 'b. deed' अपयशोमलिनं कर्म; 'b. guard' दुर्वृत्तः, दुराचारः, अधमः, खलः. -*s.* कृष्णः, कृष्णवर्णः; 'clothed in b.' नीलवस्त्रः. **-en**, *v. t.* कृष्णीकृ 8 U, श्यामी-नीलीकृ. 2 दुष् c. (दूषयति), कलंकयति (D.), *See* **Stain**. **-ish**, *a.* ईषत्कृष्ण, आनील. **-ness**, *s.* कृष्णिमन् *m.*, श्यामत्वं, नीलता, कालिमन् *m.*, तमस् *n.*, तिमिरं **-smith**, *s.* कर्मकारः, लोहकारः, अयस्कारः

Bladder, *s.* मूत्राशयः, वस्ति *m.*, *f.*

Blade, *s.* (Of a sword) धारा, पत्रं, फलं. 2 (Of grass) दलं, कांडं, अंकुरः. 3 स्कंधास्थि *n.*

Blain, *s.* स्फोटः, व्रणः-णं.

Blame, *v. t.* निंद् 1 P, गर्ह् 1, 10 A, उपालभ् 1 A; दोषं क्षिप् 6 P, or आरुह् c. (रोपयति), *See* **Censure**, 'I am not to b.' नाहमपराधी, न ममात्र दोषः -*s.* दोषः, अपराधः. 2 गर्हा, आक्षेपः, उपालंभः, निंदा, जुगुप्सा; 'lays the b. on another' अन्यस्मिन्दोषं

क्षिपति. -able, a. निंद्य, निंदनीय, गर्हणीय, गर्ह्य, वाच्य; 'he is not b. or to blame' स न दोषास्पदं-दोषपात्रं. -er, s. निंदकः, परिवादकः, अधिक्षेपकः,-less, a. अनिंद्य, निर्दोष, निष्कलंक, विशुद्ध (pure). -lessness, s. अनिंद्यता, अनवद्यता (अहो अनवद्यता रूपस्य M. 2), अवाच्यता, दोषाभावः.

Blanch, v. t. शुक्लीकृ 8 U, धवलीकृ. 2 निस्तुषयति (D.), त्वचं निष्कुष् or अपनी 1 P. 3 Avoid, q. v.

Bland, a. मृदु, कोमल, मसृण, सौम्य श्लक्ष्ण; 'b. in speech' प्रियंवद, -ish, v. i. शां-(सां)त्व् 10, चाटूक्तिभिः मुद् c., अनुनी 1 P, उपच्छंद् 10. -ishment, s. विलासः, विभ्रमः. 2 प्रियवाक्यं, चाटूक्ति f., मधुरभाषितं, उपच्छंदनं, अनुनयः.

Blank, a. शुभ्र, शुक्ल; 'b. with fear' भयविवर्णः-विवर्णानन:. 2 शून्य, रिक्त, लेखारहित. 3 एकांत, अत्यंत; 'b. despair' एकांततो नैराश्यं. 4 अनुप्रास-यमक-हीन (verse). -s. लेखाशून्यं पत्रं. 2 शून्यता; रिक्तं, शून्यं.

Blanket, s. कंबलः, ऊर्णायुः, रल्लकः

Blare, v. i. उच्चैः नद् s. उच्चनादः, उद्घोषः.

Blarney, s. *See* **Flattery.**

Blaspheme, v. t. ईश्वरं निंद् 1 P or अवमन् 4 A, or अभिशप् 1 U.-ous, a. ईश्वरनिंदक, पाषंडिन्. -y, s. पाषंडता, ईश्वरनिंदा.

Blast, s. वात्या, वातः, वायुवेगः, प्रभंजनः, झंझानिलः. 2 ध्मानं (of horns). 3 विनाशः, क्षयः, अपायः. -v. t. विनश् c., विहन् 2 P, म्लानीकृ 8 U, विशृ c., क्षै c. (क्षपयति); 'b. ed by lightning' अशनि-विद्युत्-हत -er, s. विनाशकः.

Blatant, s. *See* **Noisy.**

Blaze, v. i. ज्वल् 1 P, प्र-उत्°-, दीप् 4 A, सं-उत्-प्र-°; 'b. ing' उज्ज्वल, प्रदीप्त, देदीप्यमान, भास्वर, *See* **Bright,** 'b. abroad' प्रकाश् c., प्रख्या c. (ख्यापयति). -s. प्रभा, अर्चिस् f., n., दीप्ति f., ज्वाला; 'b. of light' रश्मि-अंशु-जालं.

Blazon, v. t. भूष् 10, अलंकृ 8 U. 2 प्रख्या c. (ख्यापयति), प्रकाश् c., उद्घुष् 10.

Bleach, v. t. निर्णिज् 3 U, धाव् 1 P, 10, धवली-कृ 8 U. -ed, a. धौत, निर्णिक्त. -er, s. धावकः, वस्त्रनिर्णेजकः.

Bleak, a. अतिशीत (winter); शिशिर, हैमंत (ती f.), हिमशीत. 2 (fig.) निरानंद, अशुभ.

Blear-eyed, a. क्लिन्नाक्ष, चुल्ल, चिल्ल, पिल्ल; 'b. eye' चुल्लः &c.

Bleat, v. i. रेभ् 1 A, मेमें शब्दं कृ 8 U, उ 1 A. -ing, s. रेभणं, मेषरुतं, उरभ्रनादः.

Bleed, v. t. रक्तं-रुधिरं &c. (blood) स्रु c. or स्रु c. or मोक्ष् 10, with gen. of person or part bled; 'they b. the wound' क्षते रक्तमोक्षणं कुर्वंति.-v. i. रक्तं-रुधिरं स्रु 1 P, or क्षर् 6 P, or प्रवह् 1 P; 'his hand b. s' तस्य हस्तात् रुधिरं स्रवति; 'b. ing profusely' रुधिरमार्गमुक्तिनिस्यंदिन् (Mal. 5); 'to b. for one's country' स्वदेशाय जीवितं त्यज् 1 P. -er, रक्तस्रावकः-मोचकः. -ing, s. रक्तस्रावः, रक्तमोक्षणं, रक्तस्रुति f., रुधिरक्षरणं.

Blemish, s. दोषः, कलंकः, छिद्रं; 'un-b. ed' निष्कलंक, निर्दोष. 2 अपयशस् n., अकीर्ति f. -v. t. मलिनयति (D.), कलंकयति (D.), दुष् c. (दूषयति).

Blench, v. i. सहसा संकुच् 1 P. 2 सहसा अपसृ 1 P or अपक्रम् 1 U, 4 P or निवृत् 1 A; पराङ्मुख (खी v.) भू 1 P

Blend, v. t. मिश्र् 10, संयुज् 10, एकत्र कृ 8 U; 'to be b. ed' संपृ pass.; संमिल् 6 P, एकीभू 1 P. -ed, a. संमिश्र, व्यामिश्र, संकीर्ण संसृष्ट, मिश्रीकृत. 2 एकरूप, एकीभूत.

Bless, v. t. Gen. ex. by Imperative or Benedictive of verb; 'I b. that you may get a son' पुत्रं लभस्व or लभ्यास्त्वं. 2 आशास् 2 A, आशिषं धृ 3 U; विद् 1 P (with loc.); त्वयि वितरतु भद्रं (U. 3) 'b you with auspicious good. 3 सुखिन्-धन्य a. कृ 8 U, 'was b. ed with a son' सुतलाभेन कृती बभूव.-ed, a. धन्य, महाभाग, कल्याण (णी f.), मंगल, सुखिन्, सुभाग्य; 'of b. memory or name' सुगृहीतनामन् a. (म्नी f), पुण्यश्लोक. -edness, s. धन्यता, कृतार्थता 2 परमानंदः, परमसुखं; परं पदं, अपवर्गः. -ing, s. आशिस् f, आशीर्वादः, आशीर्वचनं. 2 वरः, हितं, उपकारः, कुशलं, धन्यत्वं; लाभः, सुखं.

Blight, v. t. विफलीकृ 8 U, नश् c., *See* **Blast**; 'schemes of policy b. ed by opposing fate' विगुणविधिविपाकाकारा कर्ते हीनाः (Mu. 6). -s. नाशः, क्षयः.

Blind, a. अंध; 'born b.' जन्मांधः, 'b. following the b.' अंधपरंपरा; 'b. of one eye' अक्ष्णा काणः. 2 अज्ञान, हतज्ञान.-v. t. अंधीकृ 8 U, अंधयति (D.); 'b. ed by rage' क्रोधांधः; 'b. ed by lust' कामांधः &c. -s. तिरस्करिणी, व्यवधानं, यवनिका. 2 छद्मन् n., कपटं. -fold, v. t. वस्त्रेण चक्षुषी पिधा 3 U or बंध् 9 P or अवरुध् 7 U: 'b. ed' बद्धनेत्र, अवरुद्धनयन. -ly, adv. अंधवत्, असमीक्ष्य, रभसा, साहसेन. -ness, s. अंधता. 2 अज्ञानं, मोहः.

Blink, v. i. निमील् 1 P, निमिष् 6 P. -s., -ing, निमि(मे)षः, दृष्टिनिपातः, निमीलनं.

Bliss, s. परमसुखं, सुखातिशयः, महर्षः, धन्यता, आनंदसुखं. 2 अपवर्गः; *See* **Beatitude.**

-ful, *a*. आनंदमय (यी *f*.), धन्य, सानंद, परमसुखभाज्; सुखावह. **-fully**, *adv*. परमानंदपूर्वकं, सानंदं, ससुखं. **-less**, *a*. सुखहीन-रहित, निरानंद.

Blister, *s*. त्वक्स्फोटः, शोफः; व्रणः-णं, 'b. on the foot' पादस्फोटः, विपादिका. 2 स्फोटजननः उपनाहः. **-v**. *t*. स्फोटं उत्पद् *c*.

Blithe, Blithesome, *a*. हृष्ट, प्रमुदित, सानंद, प्रसन्नवदन. **-ly**, *adv*. सहर्षं, सानंदं, हृष्टमनसा. **-ness**, *s*. प्रहर्षः, आह्लादः, आनंदः

Blizzard, *s*. सहिमवात्या, हिमवर्षयुतः प्रभंजनः.

Bloat, *v*. *t*. श्वि *c*., आप्यै *c*., पीनीकृ 8 U. **-v**. *i*. स्फाय् 1 A, श्वि 1 P, आप्यै 1 A. **-ed**, *a*. शून, पीन, स्फीत, आप्यायित. 2 दृप्त.

Block, *s*. काष्ठं, शिला (of stone); 'b. of snow' शिलीभूतं हिमं, घनं हिमं. 2 वध्यशिलाकाष्ठं. 3 उपरोधः, प्रत्यूहः, अंतरायः. 4 पिंडः, भारः. **-up**, *v*. *t*. नि-,अव-,प्रति-,रुध् 7 U, स्तंभ् 9 P, प्रतिबंध् 9 P, आवृ 5 U, (आवृत्य पंथानमजस्य तस्थौ R. vii. 31). **-ade**, *v*. *t*. रुध् 7 U, *See* **Besiege**. **-s**. उप-अव-रोधः, परिवेष्टनं. **-head**, *s*. स्थूलबुद्धिः, स्थूलधीः, मूढः, दुर्बुद्धिः, मूर्खः.

Blood, *s*. रक्तं, रुधिरं, शोणितं, लोहितं, अस्रं, असृज् *n*., 'shed b.' रुधिरं पत् *c*.; 'take one's b.' हन् 2 P. 2 गोत्रं, वंशः, कुलं; 'of whole b.' सोदर, सोदर्य, सगर्भ; समाभि; 'of noble b.' कुलीन, अभिजात; 'of royal b.' राजकुलप्रसूत. 3 (Temper) शीलं; 'hot-b. ed' तीव्रकोप, सुलभकोप; 'b. rising to the cheeks' कोपप्रदीप्ताननः. **-v**. *t*. रक्तेन लिप् 6 P or अंज् 7 P. **-less**, *a*. रक्तहीन. 2 रक्तस्रावं विना. **-letter**, *s*. रक्तस्रावकः, रुधिरमोक्षकः. **-red**, *a*. रक्त-लोहित-वर्ण. **-shed**, *s*. रक्तस्रावः-पातः, नृहत्या. **-shot**, *a*. रक्तपूर्ण, शोणिताप्लुत. **-thirsty**, *a*. रुधिरप्रिय; जिघांसु, वधोद्यत. **-vessel**, *s*. रक्तवाहिनी, नाडी, शिरा, असृग्वहा, धमनी. **-y**, *a*. रक्तमय (यी *f*.), रक्ताक्त. 2 क्रूर, मारात्मक, नृशंस; 'a b. battle it was' तस्मिन् युद्धे महारक्तस्रावोऽभूत्.

Bloom, *s*. *See* **Blossom** below; 'b. of youth' यौवनभरः, नवयौवनं; 'in the b. ing youth' प्रथमे वयसि, नवयौवने. 2 रागः (कपोलरागः). **-v**. *i*. फुल्ल 1 P, विकस् 1 P, स्फुट् 6 P, 2 वर्ध् 1 A, एध् 1 A.

Blossom, *s*. पुष्पं, कुसुमं, मुकुलः-लं, प्रसवः, **-v**. *i*. स्फुट् 6 P, प्रफुल्ल् 1 P, भिद् pass.; विकस् 1 P, मुकुलैः संबद्ध् *a*. भू. **-ed**, **-ing**, *a*. स्फुटित, प्रफुल्ल, विकसित, भिन्न, विकच, स्फुटितकुसुम; स्मित.

Blot, *s*. कलंकः, दोषः, लक्ष्मन् *n*., अंकः, लांछनं *n*. 2 लोपः, व्यामर्शः. **-v**. *t*. मलिनयति (D.), दुष् *c*. (दूषयति), कलंकयति (D.), कलुषीकृ 8 U. 2 अस्पष्टीकृ; 'b. out' विनश् *c*., उच्छिद् 7 P, विलुप् *c*., व्यामृश् *c*., व्यामृश् *c*., 'b. ing paper' मसीशोषकः, कं पत्रं.

Blotch, *s*. किलासं, सिध्मं; स्फोटः विस्फोटः व्रणः-णं, सिध्मन् *n*.; 'having b. es' किलासिन्, सिध्मल. **-v**. *t*. मलिनयति D.)

Blow, *s*. आ-अभि-घातः, प्रहारः पातनं, निर्घातः; 'Oh ! the hard b. of Fate' अहह दारुणो दैवनिर्घातः (U. 2); 'b. with the fist' मुष्टिघातः-प्रहारः; 'to strike a b.' मुष्टिना तड् 10 or हन् 2 P or प्रहृ 1 P or अभि-आ-हन् 2 P; युध् 4 A, युद्धार्थं संमिल् 6 P. 2 स्फुटनं, विकासः, फुल्लनं. **-v**. *i*. *See* **Blossom**; oft. by स्मि 1 A; 'b. n Pâtala flower' स्मितपाटलं. 2 वा 2 P, वह् 1 P, प्रवह्. 3 श्वस् 2 P, उच्छ्वस्, विनिश्वस्. **-v**. *t*. उद्-हन् 2 P, उद्-धू 9 U, उत्-क्षिप् 6 P, वह्. 2 उत्-, श्वि *c*., स्फाय् *c*. (स्फावयति).; 'dust b. n by wind' अनिलोद्धूतं रजः. 3 (As an instrument) ध्मा 1 P, मुखमारुतेन पूर् 10, (स्नानशंखानामापूर्यमाणानां Ka. 16); 'b. hot and cold' निग्रहानुग्रहौ (युगपद्) प्रकटयति (D.). **-away**, उद्-हन्, उद्धृ, उत्क्षिप्. **-out**, निर्वा *c*. (निर्वापयति). **-up**, वि-उत्-धृ, सहसा उन्मूल् 10. **-upon**, धिक्कृ 10. **-ing**, *s*. विकासः, व्याकोशः, स्फुटता, प्रोत्फुल्लता. 2 वातः; श्वासः. **-pipe**, *s*. धमनी; वेणुधमनी.

Blubber, *s*. तिमिमेदस् *n*. **-v**. *i*. अतिरोदनात् उच्छूनमुख *a*. (खी *f*.) भू. **-ed**, *a*. उच्छून, स्फीत.

Bludgeon, *s*. लगुडः, गदा.

Blue, *a*. नील, श्याम. **-s**. नीलः, नीलिमन् *m*., नीलवर्णः. **-ish**, *a*. आनील, ईषन्नील.

Bluff, *a*. स्थूल; *See* **Big**. 2 रूक्ष, परुष, उग्र.

Blunder, *s*. प्रमादः, स्खलितं, दोषः. **-v**. *i*. प्रमद् 4 P, स्खल् 1 P, भ्रम् 1, 4 P. **-er**, *s*. प्रमादिन् *m*., स्खलनशीलः. **-ing**, *a*. प्रमादिन्, प्रमत्त, अनवधान, अदक्ष. **-ingly**, *adv*. सप्रमादं, स्खलनपूर्वं.

Blunt, *a*. धाराहीन, अतीक्ष्ण, कुंठित, निस्तेजस्. 2 स्थूल, घन; मंद, अविदग्ध. 3 सरल, अजिह्म, ऋजुप्रकृति. 4 रूक्ष, परुष, कर्कश, असभ्य. **-v**. *t*. कुंठीकृ 8 U, तीक्ष्णतां विलुप् *c*.; कृ with (*a*.); तेजो हृ 1 P. 2 न्यूनीकृ, शम् *c*. (शमयति). **-ly**, *adv*. सरलतया, अजिह्मं; परुषोक्त्या, सपारुष्यं; अविनयं. **-ness**, *s*. अतीक्ष्णता, स्थूलता, पारुष्यं, &c.

Blur, *s*. कलंकः, मलं, दूषणं. **-v**. *t*. मलिनयति (D.), मलेन लिप् 6 P.

Blurt, *v. t.* असमीक्ष्य-अविचार्य-वद् 1 P.

Blush, *v. i.* लज्जां नट् 10, ह्री 3 P, लज्ज् 6 A, त्रप् 1 A, व्रीडया-त्रपया-अधोमुख *a.* (खी *f.*) भू 1 P. **2** अरुणीभू, लोहितायते (D.). –*v. t.* अरुणीकृ 8 U. –*s.* अरुणिमन् *m.*, रक्तिमन् *m.*, कपोलरागः. **2** लज्जा, व्रीडा, त्रपा, ह्रीः; 'put to b.' ह्री c. (ह्रेपयति). **–ing,** *a.* प्रफुल्ल, विकसित; 'bears b. honors' संमानरूपाणि विकसितकुसुमानि धारयति, संमानरूपपुष्पभरेणानतः **2** (Blush-ful) लज्जित, सव्रीड, सत्रप, लज्जावनत, ह्रीपरिगत, त्रपाधोमुख (खी *f.*).

Bluster, *v. i.* गर्ज् 1 P, तुमुलं-कोलाहलं कृ 8 U, उच्चैः आरट् 1 P, उत्क्रुश् 1 P. **2** विकत्थ् 1 A, श्लाघ् 1 A. **3** तर्ज् 10 A, भर्त्स् 10 A. **–er,** *s.* कलहकारः, दांभिकः, विकत्थिन्, आत्मश्लाघापरः –*s.*, **–ing,** *s.* गर्जनं, तुमुलं, कोलाहलः; उच्चैः आरटनं, उत्क्रोशः.

Boa-constrictor, *s.* अजगरः, शयुः, वाहसः.

Boar, *s.* वराहः, किरिः-रः, शू(सू)करः, कोलः, घृ(घु)ष्टिः, पोत्रिन् *m.*, किटिः, दंष्ट्रिन् *m.*, घोणिन् *m.*, स्तब्धरोमन् *m.*, क्रोडः, भूदारः. **–ish,** *a.* वाराह (ही *f.*). **2** असभ्य, ग्राम्य.

Board, *s.* फलकः-कं; भोजनासनं, काष्ठखंडं. **2** ग्रासः, भोजनं, आहारः. **3** सभा, परिषद् *f.*, समाजः, गणः, वर्गः. **4** नौकातलं-पृष्ठं; 'to go on b. a ship' पोतं आ-अधि-रुह् 1 P; 'on b.' नौकारूढ *a.*, नौतले. **5** अष्टापदं, शारि-फलं. –*v. t.* बलात् नावं आरुह् 1 P. **2** फलकैः आस्तृ-स्तृ 5, 9 U. **–er,** *s.* निरूपितमूल्येन भोजक *m.*

Boast, *v. i.* विकत्थ् 1 A दृप् 4 P, (with instr.) नात्मना दृप्यति; आत्मानं श्लाघ् 1 A, गर्वं वह् 1 P (with gen.); (सुधा पो-पनमर्थं वहसि M. 4). **–er,** *s.* आत्मश्लाघिन् *m.*, विकत्थनशीलः, शूरंमन्यः. **–ful,** *a.* आत्मश्लाघापर, विकत्थन, दृप्त, गर्वित, अव-लिप्त. **–fully,** *adv.* सगर्व, सदर्पं, विकत्थन-पूर्वं. **–ing,** *s.* आत्मश्लाघा, अहंकारोक्ति *f.*, दर्पः, विकत्थनं, गर्वः. **–ingly,** *adv.* सगर्वं, सदर्पं.

Boat, *s* नौः, तरीः, तरणि-णी *f.*; 'a small b.' उडुपं, नौका, प्लवः, कोलः; 'b. man' *s.* नाविकः, पोतवाहः, औडुपिकः; 'b. swain' *s.* मुख्यनाविकः, कर्णधारः.

Bob, *v. t.* तड् 10; *See* **Beat. 2** Crop, q. v. –*v. i.* इतस्ततो लुट् 6 P, 1 A, स्फुर् 6 P, कंप् 1 P.

Bobbin, *s.* तंतुकील, सूत्रनालिका.

Bobtail, *s.* छिन्नपुच्छधारिन् *m.* छिन्नपुच्छः.

Bode, *v. t.* शुभाशुभं सूच् 10; आदिश् c., कथ् 10., प्राक् कथ् 1 P, *See* **Predict;** 'absence of delay b. s future success' अव्या-क्षेपो भविष्यंत्याः कार्यसिद्धेर्हि लक्षणं (R. x. 6); 'b. s evil to the country' जन-पदस्य अनिष्टशंसि-सूचक, अशुभचिह्न-लक्षणं. **–ment,** *s.* शुभाशुभलक्षणं; पूर्वचिह्नं, निमित्तं.

Bodice, *s.* कंचुकः, चोलः, कूर्पासकः-कं.

Bodkin, *s.* सूचि-ची *f.* **2** छुरिका, वेधनिका, कृपाणिका.

Body, *s.* शरीरं, कायः, देहः, विग्रहः, अंगं, वपुस् *n.*, कलेवरं, तनु-नू *f.*, गात्रं; 'dead b.' शवः-वं, कुणपः. **2** (Some b.) कः or का or किम्-अपि or चित् or चन, जनः, लोकः. **3** पदार्थः, वस्तु *n.* **4** समवायः, समूहः, संघातः, वृंदं, समाजः, समुदायः; 'in a b.' समेत *a.*, संहत *a.*, एकत्र मिलित *a.* **5** समा-गमः, श्रेणी. **6** कांडः-डं, स्कंधः; 'b. of the house' गर्भः, अभ्यंतरं, जठरं; 'b. of troops' सैन्यदलं; 'b. guard' आसन्नपरिचारका-रिका, परिवारगणः. **–Bodiless,** *a.* अ (अन्) in comp. with (*s.*); अंगं, &c. **–Bodily,** *a.* शारीरिक-दैहिक-कायिक (की *f.*); gen. (*s.*) in comp.; 'b. pain' शरीरवेदना, देहक्लेशः &c. –*adv.* सशरीरं, सांगं. **2** साक्षा-द्रूपेण.

Bog, *s.* अनूपः, कच्छभूः, पंकः. **–Boggy,** पंकिल, आनूप (पी *f.*).

Boggle, *v. i.* वि-आ-शंक् 1 A, संदिह् 2 U, विकल्प् 1 A. **–er,** *s.* शंकितमतिः, शंकाशीलः

Bogus, *a.* छाद्मिक.

Bogy, *s.* पिशाचः, भूतः.

Boil, *v. t.* पच् 1 P, उत्क्वथ् 1 P, श्रा 2 P. –*v. i.* क्वथ् pass., तप्-पच् pass.; 'b.ing with anger' कोपपरीतमानसः, संतप्तचित्तः **2** फेनायते (D.). –*s.* व्रणः-णं, स्फोटः, विस्फोटः, पिटकः, पिट(टि)का, गंडः. **–ed,** *a.* उत्क्वथ, पक्व, स्थालीपक्व. **2** श्राण, शृत. **–er,** *s.* स्थाली, पिठरः-रं; उखा.

Boisterous, *a.* गर्जनकारिन्; प्रचंड, उत्कट; 'b. noise' कोलाहलः, तुमुलरवः, उच्चैरा-क्रोशः. **2** कलह-तुमुल-कारिन्; 'b. laugh' अट्टहासः. **–ly,** *adv.* प्रचंडं, उत्कटं, कोलाह-लेन. **–ness,** *s.* प्रचंडता, &c.

Bold, *a.* शूर, साहसिक (की *f.*), साहसपर. **2** (Of things) साहसाभास, साहसं, (इति वचनं साहसमात्रं S. B. 79). **3** (Rude) धृष्ट, निर्लज्ज, अविनीत. **4** प्रगल्भ, निर्विशंक, निर्भय, निर्भीक. **5** सुप्रकाश, स्पष्ट; 'he made b. to say' स निर्भयमुवाच; 'to be b.' धृष् 5 P. **–ly,** *adv.* साहसेन, निर्भयं, प्रगल्भं; धृष्टतया. **–ness,** *s.* साहसं, शौर्यं. **2** धृष्टता, अविनयः. **3** प्रगल्भता, निर्भयता.

Bole, *s.* स्कंधः, प्रकांडः.

Boll, *s.* नालि-ली *f.*; कांडः-डं.

Bolster, *s.* उपधानं, उपबर्हः; बधः; आलंबः –*v. t.* (up) संस्तंभ् 9 P. समालंब् 1 A.

Bolt, *s.* अर्गलार्गधः, अर्गलं, कवाट, कवाट-टी. 2 शूलः-लं, शङ्कुः, शरः. —*v. t.* अर्गलेन बन्ध् 7 U or पिधा 3 U or बंध् 9 P; कीलयति (D.). 2 निरुध्य भुज् c. or चल् c. —*v. i.* (away, out) सहसा-अलक्षितं निर्गम्-निःसृ 1 P, or अपक्रम् 1 U, 4 P, or अपया 2 P.

Bolus, *s.* गुटी, गुलिका.

Bomb, *s.* आग्नेयगोलः. —**ard**, *v. t.* आग्नेयगोलैः अव-कृ 9 P, or छिद् 9 U, 10, or चूर्ण् 10.

Bombast, *s.* दुर्वचनं, अतिशयोक्ति *f.*, असारं वचनं, निःसारा उक्तिः. —**ic**, —**ical**, *a.* असार; दुर्वचनात्.

Bonafide, *a.* निर्व्याज, निर्व्यलीक. 2 *adv.* वस्तुतः, सत्यतः. —**s**, *s.* निर्व्याजता, निर्व्यलीकता.

Bond, *s.* बन्धः, बंधनं, पाशः, जालं; (fig. also); निगडाः (pl.); 'b. of love' प्रेमबंधः-पाशः. 2 संश्लेषः, संहति *f.*, संधिः, संबंधः. 3 प्रतिज्ञापत्रं-लेख्यं, समयपत्रं. 4 समयः, नियमः, संविद् *f.* —**age**, *s.* बंधनं, दासत्वं; 'died in b.' का गृहे-दासत्व-स्थायां मृतः; 'bond-maid' दासी, चेटी; 'bondman' दासः, भृत्यः, किंकरः.

Bonbon, *s.* मोदकः, शर्करान्वितं खाद्यं.

Bone, *s.* अस्थि. *n.*; 'set a b.' त्रुटितास्थि संधा 3 U. —**less**, *a.* अस्थिहीन, निरस्थि. —**y**, *a.* अस्थिमय (यी *f.*). 2 अस्थिमत्, अस्थिपूर्ण.

Bonfire, *s.* जयसूचकः अग्निः.

Bonhomie, *s.* सौजन्यं, सुजनता.

Bonmot, *s.* नर्मवचनं, रसिकोक्ति *f.*

Bonnet, *s.* स्त्रीधृतं शिरोवेष्टनं, शिरस्कं.

Bonny, *a.* सुंदर (री *f.*); रूपवत् *See* **Beautiful**. 2 हृष्ट, सुप्रीत, प्रहृष्ट. 3 हृष्टपुष्ट, सुललित.

Bonton, *s.* विनीताचारः, सुजनता.

Bonus, *s.* वेतनातिरिक्तं दानं.

Bonvivant, *s.* सुखैकवृत्ति *m.*

Booby, *s.* मंदबुद्धिः, मूढः, मूर्खः.

Book, *s.* पुस्तकं, ग्रंथः; 'part of a b.' अध्यायः, पर्वन् *n.*; 'b. case' ग्रंथाधारः, ग्रंथकुटी; 'b. mate' सहाध्यायिन् *m.*; 'b. worm' ग्रंथपाठनाशकः. —*v. t.* लेख्ये आरुह् c. —**ish**, *a.* पुस्तकपठनालुब्धः; व्यवहारानभिज्ञ, अव्यवहार्य.

Boom, *s.* वातवसनयष्टि, *f.* 2 नौकाप्रवेशरोधकं.

Boon, *s.* वरः, प्रसादः, अनुग्रहः. —*a.* हृष्ट, विलासिन्, उदार, प्रहृष्ट. 'b. companion,' *s.* सहपायिन् *m.*, सहभोजिन् *m.*

Boor, *s.* ग्राम्यः जनः, ग्रामिकः, वृषलः —**ish**, *a.* ग्राम्य, अशिष्ट, असभ्य.

Boot, *v. t.* or *s.* *See* **Avail**. —*s.* उपानह् *f.*, पादुका, पादत्रं. —**less**, *a.* निष्फल, व्यर्थ, निरर्थक, मोघ, निर्गुण.

Booth, *s.* पटमंडपः, उपकार्या, पटभवनं.

Booty, *s.* लोप्त्रं, लुंठितं, लुंटनं.

Borax, *s.* रसशोधनः, टंकः.

Border, *s.* पर्यंतः-तं, प्रांतः, परिसरभूमि *f.*, उत्संगः, उपांतः. 2 (Of a garment) अंचलः, दशा. 3 सीमंतः, सीमा, सामंतं. 4 तीरं, कूलं, तटं (of a river); 'b. of a forest' वनांतः. —*v. i.* (on, upon) Ex. by वृत् 1 A, स्था 1 P, with (*s.*); जनस्थानपर्यंतवर्तीनि दीर्घारण्यानि (U. 2) 'large forests b. ing on Janasthāna'; 'his age b. s on 20' विंशतिवर्षवयोवस्थां स्पृशति, विंशतिवर्षदेशीयोऽसौ. 2 कल्प, प्राय, in comp.; 'his condition b. s on poverty' तस्य दशा दारिद्र्यसंनिकृष्टा, दारिद्र्यकल्पा. —*v. t.* प्रांतयति (D.), पर्यंतं कृ 8 U; पर्यंते निषिव् c.; 'garment b. ed with silk' निर्मितकौशेयप्रांतं वसनं. —**ing**, *a.* प्रत्यंत, पर्यंतस्थ, निकटस्थ.

Bore, *s.* छिद्रं, रंध्रं. 2 वेधनी. 3 द्रुतिरं, छिद्रव्यासः. 4 वेलोर्मि *f.*, वेलातरंगः. —*v. t.* व्यध् 4 P, छिद्रं कृ 8 U. —**er**, *s.* वेधकः.

Boreal, *a.* उदीचीन, उत्तर.

Boreas, *s.* उत्तरवायुः.

Borrow, *v. t.* ऋणं कृ 8 U, or मार्ग् 10 A or ग्रह् 9 P. 2 अन्यस्मात् ग्रह् or आदा 3 A, or लभ् 1 A. —**er**, *s.* ऋणकर्तृ-ग्रहीतृ *m.*, ऋणयाचकः.

Bosom, *s.* वक्षस् *n.*, उरस् *n.*, क्रोडं, वक्षःस्थलं. 2 गर्भः, अभ्यंतरं. 3 हृदयं, चित्तं, मनस् *n.*; 'b. friend' हृदयंगमः सखा, मित्रवरः. 4 स्तनः, कुचः, वक्षोजः.

Boss, *s.* गंडः. 2 निर्माणकः. —**ed**, *a.* गंडचिह्न.

Botany, *s.* उद्भिद्विद्या, औषधिशास्त्रं, वनस्पतिशास्त्रं. —**ist**, *s.* औषधिशास्त्रज्ञः.

Botch, *s.* व्रणः-णं, स्फोटः. 2 छिद्रं, दोषः. —*v. t.* जीर्णवस्त्राणि सिव् 4 P, दुष्ट्वा संधा 3 U.

Both, *pron. a.* उभौ, उभे; उभय-द्वि in comp.; उभयं, द्वयं; 'b. sides' उभयपक्षौ; 'on b. sides' उभयतः; 'in b. ways' उभयथा; 'in b. places' उभयत्र. 2 Ex. by च-च, तथा; 'does b. good and bad' शुभं चाशुभं च विदधाति.

Bother, *v. t.* क्लिश् 9 P, पीड् 10, बाध् 1 A.

Bottle, *s.* काचकूपी-पात्रं-भाजनं. —*v. t.* काचकूप्यां निषिच् c.

Bottom, *s.* तलं, अधोभागः; 'examine it to the b.' आमूलं-तलं परीक्षस्व तत्; 'you are at the b. of this plot' अस्य कपटप्रबंधस्य त्वं मूल-प्रधान-कारणं, त्वं प्रधानः प्रवर्तकः. 2

बुध्नं, उपस्तंभः, निम्नभूः, पादः. 3 मलं, शेषं, अवशेषं. —*v. i.* (upon) आलंब् 1 A, मूल in comp. **-less,** *a.* अगाध, अतलस्पर्श.

Boudoir, *s.* नेपथ्यगृहं.

Bouffant, *a.* नेपथ्य-वेश-आध्मात.

Bough, *s.* शाखा, विटपः.

Boulder, *s. See* '**Rock.**'

Bounce, *v. i.* प्रपत् 1 P, अभि-उत्-प्लु 1 A, सत्वरं-सवेगं-धाव् 1 P or पलाय् 1 A. 2 स्वन्-ध्वन् 1 P. 3 **Boast,** q. v. —*s.* स्फोटः, ध्वनिः, अकस्मादाघातः.

Bound, *s.* प्लुति *f.*, प्लुतं, वल्गनं. 2 मर्यादा, सीमन् *f.*, सीमा, प्रांतः, पर्यंतः, अंतः. 3 प्रतिघातः, उत्पतनं. —*v. t.* Ex. by सीमा, प्रांत; 'b. ed on the south by the ocean' अस्य दक्षिणा सीमा सागरः; 'b. ed by dales on all sides' दरीपरिगतः; *See* **Border.** 2 नियम् 1 P, निग्रह् 9 P. —*v. i.* उत्प्लु 1 A, वल्ग् 1 P.**-up,** उत्पत् 1 P. **-less,** *a.* अनंत, अमित, निःसीम, निरवधि. **-Boundary,** *s.* सीमा, सीमन् *f.*, मर्यादा, पर्यंतः, प्रांतः, अवधिः.

Bounteous, Bountiful, *a.* वदान्य, उदार, मुक्तहस्त, दान-त्याग-शील. **-ly,** *adv.* अतित्यागेन, उदारवत्, मुक्तहस्तं. **-Bounty, -ness,** *s.* औदार्यं, वदान्यता, मुक्तहस्तता, त्यागिता. 2 प्रदानं, पारितोषिकं. 3 कृपा, अनुग्रहः, प्रसादः.

Bouquet, *s.* कुसुमस्तबकः, पुष्पगुच्छः.

Bourn, *See* **Boundary.**

Bout, *s.* वारः; 'drinking b.' संपीति *f.* 2 कलहः.

Bovine, *a.* गव्य.

Bow, *v. i.* नम् 1P, प्रणम् (acc. or dat.); अभिवद् c., अभिवंद् 1 A, प्रह्वीभू; चरणयोः पत् 1 P. 2 अंगीकृ 8 U, अभ्युप-इ 2 P, °गम् 1 P; oft. by प्रमाणं; 'I b. to your decision' आर्यमिश्राः प्रमाणं (M. 1) or भवतो निर्णयो मे प्रमाणं. —*v. t.* अव-आभि-नम् c. (नमयति), प्रह्वी-नम्रीकृ; 'b. ing the head down' प्रणम्य शिरसा; 'b. ed down with age' जरानमितकायः; 'b. ing down the head on the ground' अवनितलनिवेशितलोल-शिरस् *a.*; —*s.* प्रणामः, प्रणति *f.*, नमस्कारः. 2 धनुस् *n.*, चापः-पं, कार्मुकं, शरासनं, कोदंडं, इष्वासः, शरावापः; 'b. man' धन्विन् *m.*, धनुष्मत् *m.*, धनुर्धरः, धनुर्भृत् *m.*, धानुष्कः, निषंगिन् *m.*; 'b. string' *s.* ज्या, मौर्वी, गुणः, शिंजिनी; 'b. shot' बाणगोचरं, शरपथः-विषयः. —*interj.* नमः. (with dat.).

Bowels, *s.* आंत्राणि (pl.). 2 (fig.) अभ्यंतरं, गर्भः.

Bower, *s.* कुंजः-जं, लतामंडपः. 2 कुटीरः, पर्णशाला. —*v. t.* परिवेष्ट् 1 A, परिवृ 5 U or c. **-y,** *a.* कुंजवत्, लतापरिच्छन्न.

Bowl, *s.* पात्रं, भाजनं, शरावः. 2 गुलिका. 3 पिंडं. —*v. i.* गुलिकाभिः क्रीड् 1 P.

Box, *s.* पेटिका, समुद्गकः, संपुटः, पिटकः, मंजूषा. 2 मुष्टिप्रहारः-घातः, पाणिघातः. —*v. i.* मुष्टीमुष्टि प्रहृ 1 P; बाहूबाहवि-युध् 4 A or तड् 10; मल्लयुद्धं कृ 8 U. —*v. t.* मुष्टिना प्रहृ or तड्. 2 संपुटके निधा 3 U. **-er,** *s.* मल्लयोधः, बाहुयोधिन् *m.* **-ing,** *s.* मल्लयुद्धं, बाहुयुद्धं, बाहूबाहवि *ind.*

Boy, *s.* बालः-लकः, शिशुः, कुमारः-रकः, दारकः. **-hood,** *s.* बाल्यं, कौमारं, शैशवं, बालभावः. **-ish,** *a.* बालिश, बालेय. 2 शिशुयोग्य; बालसदृश (शी *f.*), बालभावसुलभ; 'b. nature' बालभावः, शिशुत्वं, बालिशता.

Boycot, *s.* व्यवसायबहिष्कारः —*v. t.* व्यवसायाद्बहिष्कृ 8 U.

Brabble, *See* **Quarrel.**

Brace, *s.* युग्म, युगं, युगलं, द्वयं, युगलं. 2 बंधः-धनं, चर्मबंधः. —*v. t.* बंध् 9 P. 2 दृढीकृ 8 U, संस्तंभ् 9 P or c., शक्ति-बलं-पुष् c. **-ing,** *a.* शक्ति-बल-वर्धक.

Bracelet, *s.* कंकणं, कटकः-कं, आवापकः, पारिहार्यः, हस्तसूत्रं, वलयः-यं; करभूषणं; 'marriage b.' विवाहकौतुकं.

Bracket, *s.* नागदंतः. 2 अर्धचंद्रद्वयं.

Brackish, *a.* क्षार, क्षाररसयुक्त.

Brag, *v. i.* विकत्थ्-, श्लाघ् 1 A; *See* **Boast.** —*s.* आत्मश्लाघा, विकत्थनं, वृथास्तुति *f.* **-ingly,** *adv.* साहंकारं, आत्मश्लाघापूर्वं. **-Braggart, (Braggadocio)** *s., a.,* विकत्थनशीलः, आत्मश्लाघिन् *m.*, आत्मश्लाघापरः, पिंडीशूरः.

Brahman, *s.* ब्राह्मणः, विप्रः, द्विजः, द्विजन्मन् *m.*, अग्रजन्मन् *m.*, भूसुरः, भूदेवः; 'a pseudo b' ब्राह्मणब्रुवः. **-ical,** *a.* ब्राह्म (ह्मी *f.*); ब्राह्मणजातीय.

Braid, *s.* कबरी, वेणि-णी *f.*, धम्मिल्लः, केशबंधः-पाशः. —*v. i.* वेणीकृ 8 U, वेणीकरणेन केशान् संग्रंथ् 9 P or रच् 10. 2 संवेष्ट्, वे 1 P, संश्लिष् c., संसिव् 4 P.

Braille, *s* अंधलिपि *f.*

Brain, *s* मस्तिष्कं, मस्तकं, गोर्दं. 2 बुद्धि *f.*, मति *f.*, **-less,** *a.* बुद्धिहीन, निर्बुद्धि. **-pan,** *s.* कपालः-लं, शिरोस्थि *n.* **-sick,** *a.* मूढमति, भ्रांतचित्त, संभ्रांत.

Brake, *s.* गुल्मगहनं, कंटकवनं. 2 चक्रबालीनं, खलीनः-नं.

Bramble, *s.* कंटकः, कंटकगुल्मः, गोक्षुरः.

Bran, *s.* तुषः, धान्यत्वच् *f*, तुस, कडंगरः.

Branch, *s.* शाखा, विटपः. 2 अंशः, शाखा, एकदेशः-भागः. 3 उपनदी, अल्पसरित् *f.* 4 अन्वयः, कुलसंतानं; वंशः. -*v. i.* शाखारूपेण विभज् pass., or भिद् pass.; 'the family b. ed into 8 parts' भिन्नोऽष्टधा विससार वंशः. (R. xvi. 3) -y, -ing, *a.* शाखिन्, शाखामय (यी *f.*), शाखावत्; विस्तीर्ण, विस्तारयुक्त.

Brand, *s.* अलातं, उल्का, दग्धकाष्ठं. 2 कलंकः, अंकः, लांछनं, अपकीर्तिचिह्नं. -*v. t.* तप्तलोहेन अंक् 10 or चिह्न् 10; 'b. ed with disgrace' अपयशोंकितः, उपक्रोशमलीमसः. -ed, *a.* तप्तलोहेन चिह्नित, दुष्कीर्तिचिह्नांकित. -new, (Bran new) *See* **Fresh** or **New.**

Brandish, *v. t.* परि-भ्रम् c (भ्रमयति), विधू 5, 9 U.

Brandy, *s.* सुरा, आसवं, वारुणी, सीधु *f.*

Brangle, *s.* कलहः, व्याक्रोशः.

Brass, *s.* पित्तलं, आरकूटः-टं, रीति-ती *f.* -y, *a.* पित्तलमय (यी *f.*). -Efflorescence, *s.* रीतिपुष्पं, पुष्पकेतु, पुष्पकं, कुसुमांजनं.

Brat, *s.* शिशुः, बालः, बटुः.

Brave, *v. t.* भर्त्स् 10 A, तर्ज् 10 A, 2 धृष् 5 P; आ-समा-ह्वे 1 A. -*a.* वीर, शूर, विक्रांत, धीर, पराक्रमवत्, वीर्य-विक्रम-शालिन्, साहसिक (की *f.*); उदार, तेजस्विन् 'fortune favours the b.' साहसे श्रीः प्रतिवसति. -*s.* शूरंमन्यः. 2 समाह्वानं. -ly, *adv.* सधैर्यं, निर्भयं, सविक्रमं, शूर-वीर-वत्. -ry, *s.* वीर्यं, शौर्यं, धैर्यं, परा-वि-क्रमः, साहसं. 2 (**Bravado**) विकत्थनं, आत्मश्लाघा.

Bravo, *interj.* साधु, साधु साधु. -*s.* घातकः, आततायिन् *m.*

Brawl, *s.* कलिः, कलहः, विवादः, द्वंद्वं, विप्रतिपत्ति *f.* -*v. i.* विवद् 1 A, कलहं कृ 8 U, कलहायते (D).

Brawn, *s.* शूकरमांसं. 2 बाहुः; बाहुः. -y, *a.* मांसल; दृढांग (गी *f.*); संनद्धशरीर.

Bray, *v. t.* चीत्काररशब्दं कृ 8 U, आरट् 1 P. -*v. t.* चूर्ण् 10, पिष् 7 P -*s.*, -ing, *s.* ची-(चि)त्कारः, खराह्वः.

Braze, *v. t.* पित्तलेन संधा 3 U. -en, *a.* पित्तलमय (यी *f.*). 2 निर्लज्ज, धृष्ट, निखपाकरण. *v. t.* धृष् 5 P. -ier, *s.* ताम्र-कांस्य-कारः, कांस्यकारिन् *m.* 3 अंगारपात्रं.

Breach, *s.* छिद्रं, रंध्रं. 2 भंगः, भेदनं, अतिक्रमः, लंघनं; 'b. of promise' प्रतिज्ञाभंगः; आज्ञाभंगः. 3 भेदः (सख्यभेदः); 'b. in a wall' संधिः, सुरंगा.

Bread, *s.* अपूपः, पिष्टकः, रोटिका. 2 अन्नं, आहारः.

Breadth, *s.* *See* under **Broad.**

Break, *v. t.* भंज् 7 P (fig. also), खंड् 10. 2 छुद्-छिद् 7 P, चूर्ण् 10, तुद् 9 P. 3 अतिक्रम् 1 U, 4 P, उल्लंघ् 1 A, 10, अतिचर् 1 P; विलुप् c. 4 भिद् 7 U, विघट् c. (स्फाटयति); विद् 9 P, 10, स्फुट् c. (as heart); 'b. fast' पारणां निर्वृत् c., प्रातराशं-कल्यवर्तं सेव् 1 A; 'b. wind' गुदरवं कृ 8 U, पर्द् 1 A; 'b. the way for' अपसृ 1 P, अप-वृ 2 P, अपक्रम्. 5 विनश् c., उच्छिद् 7 P. -*v. i.* भिद्-द्रु-भंज् pass., त्रुट् 3, 4 P, स्फुट् 6 P, (स्फुटति हृदयं), दल् 1 P. 2 प्रभा 2 P; 'the day broke' उषाः समायाता, प्रभाता रजनी, वृत्तं दिनमुखं. 3 क्षि pass., अवसद् 1 P, क्षि pass., ध्वंस् 1 A, जृ 4, 9 P. -*s.* विच्छेदः, निवृत्ति *f.*, विरामः, भंगः; 'b. of day' प्रभातं, उषःकालः, अरुणोदयः; 'the story has suffered a b' विच्छेदमाप कथाप्रबंधः (Ks. 239). -down, चूर्ण् 10; (*v. i.*) *See* **Fail.** -in upon, सहसा-सहसा-प्रविश् 6 P. -into, विनी 1 P, दृष् c. (दमयति). -into, (a house) संधिं कृत्वा प्रविश्. -loose, मुच्, विमुच् pass; 'the elephant broke loose from the post' आलानस्तंभं भंक्त्वा निर्जगाम. -off, भंज्, भंगं कृ 8 U; (*v. i.*) अकस्मात् विरम् 1 P, त्यज् 1 P, निवृत् 1 A. -open, बलात्-सहसा-उद्घट् c. or अपावृ 5 U. -out, (*v. i.*) जन् 1 P, उत्पद् 4 A, प्रादुर्भू, वृध् 2 P. 2 निर्गम् 1 P. -through, निर्भिद्, अपावृ 6 P, निरस् 4 P; *See* **Dispel.** -up, (*v. t.*) *See* **Break** (*v. i.*) 'the party broke up' सभ्याः स्वं स्वं स्थानं प्रतिजग्मुः. -upon, आहन् 2 A; 'the dawn broke upon his eyes' तस्याक्ष्णोः प्रभातमासीत् (S. 2). -with, विवद् 1 A, कलहं कृ. -er, *s.* भंजकः, भेदकः. 2 प्रस्तर or तट-भग्ना ऊर्मि *f.*, लहरि *f.* -fast, *s.* प्रातराशः, कल्यवर्तः. -water, *s.* सेतुः, धरणः.

Breast, *s.* उरस् *n.*, क्रोडं, वक्षस् *n.* 2 स्तनः, पयोधरः, वक्षोजः, कुचः, (of human beings). 3 हृदयं, अंतःकरणं, चित्तं, मनस् *n.*; 'b. high' वक्षोदघ्न (घ्नी *f.*); 'b. plate' कवचं, उरस्त्राणं; 'b work' वक्षःप्रमाणः प्राकारः. 'Make a clean b. of,' *See* **Confess.**

Breathe, *v. i.* श्वस् 2 P; प्राण् 2 P. 2 अन् 2 P; जीव् 1 P, वृत् 1 A. 3 आ-प्रत्या-उच्छ्वस्; 'b. deep' दीर्घ-स्थूलं-स्थूलं निःश्वस्; 'b. freely' उच्छ्वस्; 'b. the last' *See* **Die,** -*v. t.* (out) उद्गृ 6 P, अव-उद्-गॄ 6 P. 2 प्रवा 2 P. -**Breath,** *s.* श्वासः, निःश्वासः, उच्छ्वसितं. 2 प्राणाः (pl.); आनापानाः 'holding the b.'; असवः (pl.). 3

विरामः उपशमः. 4 उद्गारः. 5 मंदानिलः, सुखवातः; 'in the same b.' एकावसरे, समकालमेव. -ing, s. श्वासः, श्वसितं. 2 स्पृहा, इच्छा; 'b. through nose' नासिकंधमः; 'b. hole' वातायन, गवाक्षः. -less, a. प्राणहीन, निरुच्छ्वास, विचेतन. 2 मृत, उत्क्रांतवायु 3 वाहिप्राण.

Breech, s. पश्चाद्भागः, नितंबः, कटिदेशः. -es, s. कटिवस्त्रं, शाटकः.

Breed, v. t. जन् c (जनयति), उत्पद् c., प्रसू 2 A. 2 पुष् 1. 4, 9 P or c., सं c. 3 विनी 1 P. -v. i. वृध् 1 A, प्रजन्-उत्पद् 4 A. 2 गर्भवती भू, See **Conceive**; 'b. ing season' गर्भधारणकालः, उत्पत्तिसमयः. -s. वंशः, कुलं, जाति f. 2 अपत्यं, प्रजा. 3 समुत्पन्नः शावकगणः, शिशुजातं. -bred, a. जनित; संवर्धित; विनीत, 'well b.' सुविनीत, सदाचार; 'ill b.' दुर्विनीत, दुराचार. -er, s. जनकः, पोषकः, विनेतृ m. -ing, s. पोषणं, पालनं, संवर्द्धनं. 2 शिक्षणं, विनयः. 3 सभ्यता, सुशीलता; 'of good b.' सुविनीत, सुशील. 4 गर्भधारणं, गर्भाधानं.

Breeze, s. मृदुपवनः, मंदानिलः, 2 वातः, अनिलः, See **Wind**. 3 See '**Coke**,' 'Agreeable b.' सुखस्पर्शः- सुखः-वायुः. -y, a. वातवत्, वातोपजीवित.

Breviary, s. संहिता, संग्रहः. 2 स्तोत्रसंग्रहः.

Brevity, s. संक्षेपः, समासः, संहारः, संग्रहणं.

Brew, v. t. (मद्यार्थं) पच् 1 P or क्वथ् 1 P. 2 प्रचिन्त् 10, प्रकल्प् c. -age, s. मिश्रकाथः. -ery, s. मद्यकरणस्थानं.

Bribe, s. उत्कोचः, उपायनं. -v. t. उत्कोचं दा 3 U, उत्कोचदानेन वशीकृ U. -ry, s. उत्कोचदानं-ग्रहणं. 2 उत्कोचदानादानव्यापारः.

Brick, s. इष्टका, सुधा; 'burnt b.' पक्वेष्टका; 'b. bit' इष्टकाशकलं; 'b. kiln' आपाकः, पचनस्थानं; 'b. layer' लेपकः, सुधाजीविन् m.; 'b. work' इष्टकानिर्मितं.

Bridal, s. विवाहोत्सवः, उद्वाहकर्मन् n. -a. वैवाहिक (की f.), विवाहयोग्य.

Bride, s. वधूः, नववधूः, पाणिगृहीता, नवोढा. 2 कन्या, कुमारी. -groom, s. वरः, परिणेतृ m., परिग्रहीतृ m., पाणिग्राहकः; 'bride and b.' वधूवरौ. -maid, s. जन्या.

Bridge, s. सेतुः, पद्या, संवरः, 2 आलि-ली f. -छत्रः (small); 'make a b.' सेतुं निर्मा 3 A, or कृ 8 U, or बंध् 9 P; 'fort b.' संक्रमः; 'b. of the nose' नासावंशः. -v. t. सेतुना बंध् 9 P, सेतु 5 U.

Bridle, s. वल्गा, रश्मिः; 'giving the b.' to the passions' रागाधीनः, रागवशः. 2 निग्रहः, संयमः. -v. t. वल्गासनाथ a. कृ, रश्मिभिः बंध् 1 P. 2 निग्रह् 9 P, नि-सं-यम् 1, See

Control, 'by un-b. ed tongue' निर्गलया वाचा.

Brief, a. स्वल्प, अचिर, अल्पकाल, क्षणिक (की f.), अचिरस्थायिन्, संक्षिप्त, परिमित, संहृत, अदीर्घ, संकुचित; 'to be b.' किं बहुना 2 संग्रहः, संक्षेपः. 3 सारपत्रं. -ly, adv. संक्षेपतः, संक्षेपेण, समासतः, समासेन. 2 अचिरेण, आशु, क्षिप्रं. -ness, s. संक्षेपः, समासः, संहारः, परिमितता.

Briar, Brier, s. गोक्षुरः, कंटकगुल्मः. -y, a. कंटकावृत.

Brig, s. कूपकद्वययुतः पोतः.

Brigade, s. चमूः, वाहिनी, सैन्यदलं, गुल्मः-ल्मं. -ier, s. वाहिनीपतिः, चमूपतिः.

Brigand, s. दस्युः, चौरः.

Bright, a. उज्ज्वल, प्रदीप्त, भासुर, रुचिर, तेजस्विन्, भास्वत्, भ्राजमान, प्रभावत्, दीप्तिमत्, देदीप्यमान. 2 विशद, निर्मल, शुचि. 3 विश्रुत. -en, v. t. प्र-उत्-द्युत् c., प्र-उत्-दीप् c., उद्भास् c, भास् c., विराज् c. 2 विमलयति (D.), विशदीकृ 8 U. -v. i. विमलीभू 1 P, प्रसद् 1 P, प्रसादं गम् 1 P, विशदीभू, (दिशः प्रसेदुः R. III. 14). 2 द्युत्-शुभ् 1 A, See **Shine**. -ly, adv. उज्ज्वलं, विमलं, तेजसा, कांत्या. -ness, s तेजस् n, औज्ज्वल्य; द्युतिः, रुचिः, कांतिः, प्रभा, दीप्तिः, शोभा, (all fem.); भासुरत्वं, तेजस्विता; 'b. of intellect' प्रदीप्ता प्रज्ञा.

Brilliance, Brilliant, See **Bright**.

Brim, s. कंठः, प्रांतः, मुखं, धारः, कर्णः; 'to the b.' आमुखं, आकंठं. 2 (of a river) तीरं, तटः-ट. 3 अंचलः, दशा (of a cloth). -ful, a. परिपूर्ण, आकर्णपूर्ण; ex. by मय (यी f.), निर्भर; 'b. of joy' हर्षनिर्भरः.

Brimstone, s. गंधकः. -y, a. गंधकपूर्ण-मिश्रित.

Brindle, s. चित्रता, चित्रांगत्वं, शबलत्वं. -ed, a. शबल, चित्रित, कल्माषित.

Brine, s. लवणजलं. 2 बाष्पः, अश्रु n., अस्रं.

Bring, v. t. आनी, 1 P, आ-उपा-हृ 1 P, आवह् 1 P. 2 प्राप् c., आगम् c. (गमयति). 3 अनुनी 1 P, आकृष् 1 P. 4 जन् c. (जनयति), उत्पद् c., ex. by प्रसू 1 P, जन् 4 A; 'poverty b. s one to shame' दारिद्र्याद् ह्रियमेति (Mr. 1); 'b. to end' समाप् c., निर्वृत् c., अवसो 4 P; 'b. to ruin' नश् c., नाशकारणं भू; 'b. word' निविद् c., वार्ता आख्या 2 P; 'b. action' अभियुज् 7 A. -about, (to pass) सद् 5 P, 10; घट् c., (घटयति), संपद् c., आवह् 1 P; क्लृप् 1 A, संपद् 4 A, (with dat.). -down, नि-अव-पत् c. अपकृष्, अभिभू. -forth, See **Beget**. -forward, उपन्यस्, 4 P, उपाहृ 1 P, उपक्षिप् 6 P, उपाधा, उपस्कृ

2 अग्रे-पुरः-आनी, प्रसृ c., -on, आपद् 1 P, or with dat.; 'disgrace b. s on despair' परिभवः निर्वेदमावहति, निर्वेदाय (भवति); oft. by प्रभू, जन्; 's. avarice b. s on anger' लोभात् क्रोधः प्रभवति-जायते &c. -out, प्रकाश् c., प्रकटीकृ. -together, समा-नी, समुपाहृ; See Assemble. -under, आनम् c. (नमयति); 'b. under one's power' वशं नी, दम् c. (दमयति), अभिभू. -up, संवृध् c., पोषणं-पालनं-कृ 8 U (with gen.); पुष् 10.

Brink, s. तीरं, तटः-टं, कूलं. 2 प्रांतः, अंतः, पर्यंतः; धारा, उत्संगः, परिसरः, कंठः.

Brisk, a. चपल, त्वरित, क्षिप्र, अविलंब. 2 प्रबल, ससार, तीव्र; 'b. shower' धारासंपातः. -ly, adv. सत्वरं, क्षिप्रं, आशु. -ness, s. तेजस् n., सारः, सत्त्वं.

Bristle, v. i. पुलकित-रोमांचित-कंटकित a. भू 1 P; 'his body b. ing with joy' हर्षरोमांचित-पुलकित-तनुः; हृष् 4 P (of hair). -s. शूकः-कं, दृढलोमन् n., 2 शूकरलोमन् n. -ing, a. हर्षित, पुलकित, रोमांचित.

Brittle, a. भंगुर, भिदुर, सुखभेद्य, सुभंग.

Brize, s. दंशः; गोमक्षिका.

Broach, s. शूलः, शंकुः, कीलः-लं. -v. t. अपावृ 5 U. 2 निविश् c., प्रकाश् c., कथ् 10. 3 छिद्र 10.

Broad, a. विस्तीर्ण, पृथु, विपुल, विस्तृत, विशाल, परिणाहवत्, आयत; '10 yojanas b.' दशयोजनमायता (नगरी). 2 असभ्य, अश्लील, गर्हित; 'b. day-break' सुप्रभातं; स्पष्टे जाते प्रत्यूषसि (Ka. 26); 'b. day light' प्रखरतेजसि सवितरि; 'b. awake' प्रबुद्ध, उन्निद्र; 'b. breasted' व्यूढोरस्कः; विशालवक्षस्.-ness, Breadth, s. विस्तारः, परिणाहः, आयामः, विशालता, पृथुता; 'five fingers in b.' पंचांगुलं (दारु).

Brocade, s. कार्मिकवस्त्रं.

Brochure, s. लघुपुस्तकं.

Brogue, s. प्राकृतभाषा, अपभ्रंशः. 2 चर्मपादुका.

Broider, v. t. चित्र् 10, सूच्या वस्त्रे पुष्पादिकं सिव् 4 P. -y, s. सूचिकर्मन् n.

Broil, v. i. तप्-पच्-pass. -v. t. भ्रस्ज् 6 P; (fig.) संक्षुभ् c., प्रकुप् c., उद्दीप् c. -s. कलहः, द्वंद्वं, कलिः, तुमुलं.

Broker, s. निरूपितमूल्येन कार्यनिर्वाहकः. -age, s. कार्यनिर्वाहणार्थं दत्तं द्रव्यं.

Bronze, s. See Brass.

Brooch, s. वक्षोभूषणं, उरोमणिः.

Brood, v. i. (lit.) (अंडानां) उपरि-स्था 1 P, निविश् 6 P; (fig.) नि-ध्यै 1 P, पुनः पुनर् आलोच् 10; चिंताव्यग्र a. भू. -s. प्रजा, संतति f., अपत्यं. 2 समकालोत्पन्नः शावकगणः, अपत्यजातं.

Brook, s. कुसरित् f., स्रोतस् n., क्षुद्रनदी, क्षुद्र-अल्प-सरित्. -v. t. सह् 1 A, क्षम् 1 A, मृष् 4 P, 10.

Broom, s. संमार्जनी, शोधनी. 'b. stick-staff' मार्जनीदंडः; दीर्घ-कृश-यष्टिः.

Broth, s. सूपः, यू(जू)षं.

Brothel, s. वेशः, वेश्यालयः, गणिकागृहं.

Brother, s. भ्रातृ m., सोदरः, सहोदरः, सोदर्यः. 2 बंधुः, सहकारिन् m., संसर्गिन् m.; 'spiritual brethren' एकगुरवः. -hood, s. भ्रातृभावः,-त्वं, सौभ्रात्रं. 2 साहचर्यं, बंधुता, संसर्गः, समाजः. -ly, a. भ्रात्रीय, भ्रातृसदृश (शी f.); 'b. in law,' s. श्यालः, देवृ, m., देवरः (husband's brother.).

Brow, s. कटकः, उत्संगः, See Edge. 2 भ्रूः, भ्रूलता; 'knit the b. s.' भ्रूभंगं कृ 8 U, भ्रुकुटिं बंध् 9 P, भ्रुकुटिरचनां कृ. 3 ललाटं; वदनं, आननं. -beat, v. t. भ्रूभंगेन-कटाक्षेण-तर्ज् 10, or निरीक्ष् 1 A. -Bound, a. किरीटिन्.

Brown, a. कपिश, पिशंग (गी f.), पिंगल, कपिल, श्याव. -ish, a. ईषत्कपिश, आपिंगल. -ness, s. कपिशः, पिंगलवर्णः.

Browse, v. t. अद् 2 P, चर्व् 10, लंघ् 1 A, (पल्लवान् लंघितुमागच्छति bh. 4), भक्ष् 10, संदंश् 1 P. -s., -ing, s. किसलयः-यं, नवपल्लवः-वं; नवतृणं, शाद्वलं.

Bruin, s. ऋक्षः, भल्लूकः,

Bruise, v. t. अपकृ 8 U, क्षण् 8 P, प्रहारेण हिंस् 7 P. 2 मृद् 9 P, पिष् 7 P. -s. क्षतं, अपकारः, प्रहारः, आघातः. 2 पिष्टितव्रणः.

Bruit, s. ध्वनिः. 2 वार्ता, जनप्रवादः. -v. t. ख्या c. (ख्यापयति), घुष् 10.

Brunette, s. श्यामा, श्यामवर्णा.

Brunt, s. भारः; 'b. of battle' रणधुरा; संघट्टः, प्रथमाक्रमः; प्रहारः, आघातः.

Brush, s. आघर्षणी; लोममयी मार्जनी or शोधनी. 2 तूलिका, शलाका, वर्तिका. 3 संघट्टः, समाघातः. -v. t. मृज् 2 P, घृष् 1 P, घर्षणेन शुध् c. 2 मृदु स्पृश् 10, लघुत्वरया वह् 1 P. -v. i. (by) लघु घृष्. 2 अपधाव् 1 P, विसृप् 1 P. -wood, s. गुल्मः, जंगलं. -y, a. लोमश.

Brusque, a. अविनीत. 2 असंबद्ध. 3 अनवहित.

Brute, s. पशुः, तिर्यच् m. 2 नरपशुः, दुर्जनः, क्रूराचारः. -a. अ-वि-चेतन, अज्ञान. 2 क्रूरकर्मन्, असभ्य. -al, -ish, a. नृशंस, क्रूर, पशु in comp; See Cruel. 2 पशुशील, पाशव (वी f.), पशुसदृश (शी f.), पशुतुल्य. -ally, adv. पशुवत्; निर्दयं, अतिक्रौर्येण

Bubble, *s.* बुद्बुदः, स्फोटिका. 2 (fig.) असारं वस्तु, माया, वंचकः, मोहः, मायाजालं. —*v. i.* बुद्बुदायते (D). —*v. t. See* **Cheat.**
Bubby, *s. See* **Breast.**
Bubo, *s.* ग्रंथि *f.*
Buck, *s.* हरिणः, मृगः. 2 वस्त्रक्षालनार्थं जलं. 3 सुभगंमन्यः. —*v. t.* वस्त्र धाव् 1 P.
Bucket, *s.* अरघट्टः, उदंचनं, घटीयंत्रं. 2 पात्रं, द्रोणी, सेचनी-नं.
Buckle, *s.* कुडुपः, गंडकः. —*v. t.* कुडुपेन बंध् 9 P; 'to be b. ed to' परायण-आसक्त *a.* भू 1 P. —**er**, *s.* फलकः-कं, चर्मन् *n.*
Buckram, *s.* स्थूलपट्ट-पटः.
Bud, *s.* कलिका, कोरकः-कं, मुकुलः-लं, कुड्मलः; जालं, कोशः-षः, प्ररोहः, अंकुरः, पल्लवः-वं. —*v. t.*, —**ed**, *See* under **Blossom.**
Budge, *v. i.* प्रचल् 1 P, अपसृ 1 P, निःसरावृत् 1 A, त्यज् 1 P.
Budget, *s.* शाणपुटः, दृति *f.* 2 कोषः, संग्रहः, संचयः. 3 आयव्ययगणना, °पत्रं.
Buff, *s.* महिषचर्मन् *n.* 2 पांडुवर्णः.
Buffalo, *s.* महिषः; 'she-b.' महिषी; 'b. milk' माहिषं पयः.
Buffer, *s.* आघात-भंजकः or मोघीकारकः.
Buffet, *s.* मुष्टिप्रहारः, कराघातः, चपेटिका. 2 कुसूलः. —*v. t.* मुष्टिना तड् 10 or प्रहृ 1 P.
Buffoon, *s.* विदूषकः, वैहासिकः, भंडः. —**ery**, *s.* परिहासः, हास्यं, नर्मन् *n.*
Bug, *s.* मत्कुणः, उद्दंशः; 'b. bear' महाभयास्पदं, भयहेतुः.
Bugle, *s.* काहलः-ला, व्याधशृंगं-विषाणं. 2 शृंग, तूर्यं, विषाणं.
Build, *v. t.* निर्मा 3 A or c. (मापयति), प्रकृप् c., विधा 3 U, विरच् 10; 'b. upon' समालंब् 1 A, आ-समा-श्रि 1 U. —**er**, *s.* निर्मातृ *m.*, विधायकः. 2 स्थपतिः, शिल्पिन् *m.*, दारुकर्मन् *m.* —**ing**, *s.* निर्माणं, विधानं. 2 भवनं, गृहं, हर्म्यं.
Bulb, *s.* कंदः-दं, गोलमूलं. —**ous**, *a.* कंदिन्, कंदविशिष्ट. 2 कंदाकृति.
Bulge, *v. i.* बहिर्लंब् 1 A, उदराकारेण प्रलंब्.
Bulk, *s.* प्रमाणं, परिमाणं, मात्रा. 2 स्थूलता, बृहत्त्वं. 3 प्रधान-अधिक-भागः, भूयस् *m.* —**y**, *a. See* **Big.**
Bull, Bullock, *s.* वृषः, वृषभः, बलीवर्दः, ऋषभः, अनडुह् *m.*, उक्षन् *m.*, ककुद्मत् *m.* 2 वाग्दोषः, महास्खलितं, सुस्पष्टो वचनविरोधः.
Bullet, *s.* सीसकगुलिका.
Bulletin, *s.* शरीरस्थितिज्ञापकं पत्रं.
Bullion, *s.* हिरण्यं, रूप्यं.
Bully, *s.* पिंडीशूरः, दुर्दम्य; दांभिकः, कलहकारिन् *m.* —*v. t.* तर्ज् 10, भर्त्स् 10 A; आक्रुश् 1 A.
Bulwark, *s.* वप्रः-प्रं, प्राकारः. 2 आश्रयः, शरणं, संश्रयस्थानं, आलंबः; रक्षणस्थानं.
Bum, *s.* नितंबः, कटिप्रोथः.
Bump, *s.* स्फोटः, गंडः, शोफः. —*v. i.* स्फिट् 1 P. 2 **Beat**, *q. v.*
Bumper, *s.* अतिपूर्णं पात्रं; चषकः; 'b. crops' अतिप्रचुरः शस्यागमः; 'b. house' जनाकीर्णं प्रेक्षागृहं.
Bumpkin, *s.* वृषलः, जानपदः, ग्राम्यजनः.
Bumptious, *a.* सावलेप, अवलिप्त.
Bunch, *s.* गुच्छः, स्तबकः. 2 पिंडः, गंडः. 3 ग्रंथिः, शेखरः-रं. 4 पोट्टली, संघातः, संहतद्रव्य. —*v. i.* (out) पिंडीभू 1 P.
Bundle, *s.* भारः, कूर्चः, पोटलिका, गुच्छः, संघातः; 'b. of goods' भांडकं. —*v. t.* (up) गुच्छीकृ 8 U, एकत्र समाहृ 1 P.
Bung, *v. t.* छिद्रं निरुध् 7 U or पिधा 3 U. —**hole**, *s.* पात्रच्छिद्रं, पात्रधारा.
Bungalow, *s.* हर्म्यं.
Bungle, *v. i.* अदक्षतया कार्यं निर्वह् c., प्रमद् 4 P, स्खल् 1 P. —*s.* प्रमादः, स्खलितं, दोषः. —**er**, *s.* अदक्षः, प्रमादिन् *m.*, अनिपुणः. —**ingly**, *adv.* सप्रमादं, प्रमादतः, अदक्षतया.
Bunter, *s.* अकुलीना स्त्री.
Bunting, *s.* ध्वजपटः, केतुवसनं. —*s.* तरणः, प्लवः.
Buoy, (up) *v. t.* उत्तंभ् 9 P, उद्धृ 1 P, 10, आलंब् 1 A. 2 लु c. —*s.* तरणः, प्लवः. —**ancy**, *s.* लघुता, लाघवं, प्लवनशीलता.
Burden, *s.* भारः, भरः, धुर् *f.* (राज्यधुरा); 'beast of b.' धुर्यः, धुरीणः. 2 ध्रुवकं, आध्रुपद. 3 पीडाकर *a.* (री *f.*), पीडाहेतुः, भारभूत *a.* —*v. t.* भारं न्यस् 4 P or निविश् c. —**ed**, *a.* भाराक्रांत, आरोपितभार. —**some**, *a.* दुर्वह, दुर्भर, दुर्वाह. 2 पीडाकर, दुःखावह.
Bureau, *s.* आधारः. 2 लेखनस्थानं, लेखनसाधनाधारः.
Bureaucratic, *a.* अनियंत्रितशासन.
Burgh, *s.* नगरं, पुरं. —**er**, **Burgess**, *s.* नगरजनः; पारः. 2 नगरप्रतिनिधिः, पुरप्रतिनिधिः. —**ership**, *s.* नगरजनाधिकारः, पौराधिकारः.
Burglar, *s.* संधिचौरः, गृहभंगकृत् *m.*, कुड्यच्छेदिन् *m.*, संधिच्छेदकः. —**y**, *s.* सिंधिचौर्यं, गृहभंगः.
Burgomaster, *s.* नगराध्यक्षः
Burke, *v. t.* श्वासनिरोधेन हन् 2 P or व्यापद् c. or मृ. 2 त्वरितं संपद् c.
Burlesque, *a.* परिहासकर (री *f.*), हासजनक (की *f.*), परिहास्य. —*s.* परिहासः, भांडं, नर्मन् *n.* —*v. t. See* **Laugh.**
Burly, *a. See* **Big.**
Burn, *v. t.* दह् 1 P, प्लुष् 1 P, ज्वल् c. (ज्वलयति), तप् 1 P or c., उष् 1 P, दीप् c. —*v. i.* ज्वल् 1 P, दह् pass., तप् 4 A, दीप् 4 A; 'b. after' उत्कंठ् 1 A, [illegible]

10; 'b. out' ज्वल् 4 P; 'b. up' निर्दह्. —s. ज्वलनम्,-ओषः. 2 See 'Brook', —er, s. दाहकः, तापकः दीपकः. —ing, s. दाहः, दहनं, ओषः, तापः, ज्वलनं; 'b. ground' श्मशानं. —a. दाहक, तापक. 2 चंड, प्रखर; 'b. glass' सूर्यकांतः, सूर्योपलः.

Burnish, v. t. मसृण् 2 P (मसृणं चामीकरं); तिज् c., परिष्कृ 8 U. —er, s. तेजकः, धावकः.

Burrow, s. बिलं, विवरं, गर्तः-र्ता. —v. i. बिले-गर्ते-वस् 1 P.

Bursar, s. धनाध्यक्षः, कोशाधिपतिः. 2 शिष्य-वृत्त्युपजीविन् m. —y, s. कोषः, धनागारं. 2 शिष्यवृत्ति f.

Burst, v. i. स्फुट् 6 P, दल् 1 P, वि-दृ-स्फु-pass., भिद्-भंज् pass.; 'b. in pieces' शकलीभू, खंडशो भिद् pass.; 'b. into tears' सहसा रोदितुमारेभे, सहसा प्रावर्तता-श्रुधारा. —v. t. भिद्-भंज् 7 P, स्फुट् c., दृ 9 P, 10, शकलीकृ 8 U, दल् c. (दलयति); 'she b. herself' हृदयस्फोटनेन मृता. —s. स्फोटनं, विदलनं, भंगः, भेदः, 'there was a b. of applause' संभूय प्रशंसागिरः उदे-तिष्ठन्; 'b. of laughter' अट्टहासः, उच्चैर्हासः.

Burthen, s. See **Burden.**

Bury, v. t. निखन् 1 P, निगुह् 1 U, (श्मशाने-भूमौ) निधा 3 U, स्था c. (स्थाप-यति), निक्षिप् 6 P; निर्-हृ 1 P; 'this buried the king into sorrow' एतेन (वचसा) राजा दुःखमग्नो-दुःखोदधिमग्न इव-अभूत्; 'b. the hatchet' कलहाद्विरम् 1 P. —ing, s. निखननं, श्मशाने स्थापनं; 'b. ground' श्मशानं, प्रेतावासः, परेतभूमि f., पितृवनं, पितृसद्मन् n.

Bush, s. गुल्मः-ल्मं, क्षुपः, स्तंबः; 'why do you beat about the b.' अप्रस्तुतं किमिति अनुसंधीयते, (निरर्थकं किमिति वनमालो-डयसि); 'a bird in the hand is worth two in the b.' ध्रुवाणि परित्यज्य अध्रु-वाणि निषेवते नेहं, अधुवात् ध्रुव वरं, वरं तत्कालो-पनता तित्तिरिः न पुनर्दिवसांतरिता मयूरी or वरमद्य कपोतो न श्वो मयूरः.—y, a. गुल्मावृत, निबिड, गाढ, अविरल. 2 घन, स्थूल; लोमश.

Business, s. कार्यं, अर्थः, कृत्यं, कर्मन् n., व्यवसायः, व्यवहारः; व्यापारः; नियोगः (duty). 2 अर्थः, प्रयोजनं; 'what b. had you to talk with him' तेन सहालापेन किं तव कार्यमासीत्. 3 वृत्ति f., जीविका; 'a man of b.' कार्यकुशलः, दक्षकर्मन् m.

Buss, See **Kiss.**

Bust, s. ऊर्ध्वकायप्रतिमा-प्रतिकृति f.

Bustle, s. क्षोभः, आकुलत्वं, त्वरा, व्यग्रता. 2 कोलाहलः, हलहलः. —v. i. कार्यव्याकुल-त्वात् इतस्ततो धाव् 1 P or भ्रम् 1 P or चेष्ट् 1 A, or व्यवसो 4 P. —er, —ing, s., a. चापलमकृतिः, व्यवसायिन् m.

Busy, a. व्यापृत (with loc.); कार्यसमाकुल, कार्यव्यग्र; 'with what work are you b.' कस्मिन्कार्ये व्यापृतोऽसि, किमारंभस्त्वं; कार्यो-द्युक्त, सोद्योग, अतंद्रित, अनलस, व्यग्र. —v. t. व्यापृ c., कार्ये नियुज् 10 or अभियुज् 8 U. —Body, s. पराधिकारचर्चकः. —ly, adv. अतंद्रितं, सोत्साहं, मनोऽभिनिवेशेन, औत्सुक्येन, व्यग्रतया.

But, prep. अन्य, इतर, ऋते with abl. विना, विहाय, मुक्त्वा (acc.). —adv. एव, केवलं, मात्रं. —conj. तु, पुनः, (not at beginning); in 'not only but' अपि takes the place of 'but'; न केवलं रूपे शिल्पेऽप्यद्वितीया मालविका (M. 2); 'b. for' (=if it were not) यदि न; 'all b.' See **Almost;** 'next b. one' एकांतर a.

Butcher, सौ(सो)निकः, आखेटकः, मांसिकः, विशासितृ m. —v. t. विशस् 1 P, निषूद् 10, हन् 2 P. —y, s. वधः, हननं, विशसनं. 2 सूना, वधस्थानं.

Butler, s. गृहकर्म-द्रासः-कारः.

Butt, s. लक्ष्यं, शरव्यं. 2 उपहासास्पदं, परि-हासभूमि f. 3 आशयः, अभिप्रायः. 4 पार्श्व, (सुरा-) भाजनं-भांडं. —v. t. शिरसा-शृंगेण-आहन् 2 U. —end, s. घनाग्रं, स्थूलाग्रं.

Butter, s. नवनीतं, नवोद्धृतं; दधिजं, हैयंगवः, 'clarified b.' घृतं, सर्पिस् n., आज्यं; 'b. man' नवनीतविक्रयिन् m.; 'b. milk' (s.) तक्रं, अरिष्टं, कालशेयं, दंडाहतं, गोरसः, 'b. of last day's milk' हैयंगवीनं. —v. t. नवनीतेन लिप् 6 P.; (fig.) चाटूक्तिभिः प्रसद् c. or अनुनी 1 P.

Butterfly, s. चित्रपतंगः.

Buttock, s. नितंबः, कटिप्रोथः, जघनं, श्रोणि-फली f.

Button, s. गंडः, कुडुपः, 'b. hole' गंडाधारः. —v. t. गंडेन बंध् 9 P.

Buttress, s. वप्रः-प्रं, आधारार्थं कृतः प्राकारः. 2 आश्रयः, आधारः.

Buxom, a. सानंद, प्रफुल्लवदन, हृष्ट. 2 सरस, सविलास, ललित. —ly, adv. सानंदं, सरसं, ललितं. —ness, s. लीला, लालित्यं, विलासः.

Buy, v. t. क्री 9 U; 'b. off' मूल्यदानेन परिक्री. —er, s. क्रेतृ m., क्रयिकः, क्रयिन् m.

Buzz, v. i. गुंज् 1 P, रिच् 2 P. —s., —ing, गुंजितं, गुंजारवः, कलरवः.

Buzzard, s. श्येनकः. 2 स्थूल-मंद-धीः.

By, prep. Gen. ex. by instr. of noun; रामेण हतः, बाणेन हतः, &c. 2 (Near) उप in comp., or समीपे-निकटे-पार्श्वे with gen.; 'b. her father' समक्षमस्याः, पितुः पार्श्वे-

समीपे; 'by this time' अनेन समयेन; 'day by day' अनुदिवसं-दिनं, दिने दिने; 'b. god' ईश्वरं साक्षीकृत्य-ईश्वरसमक्षं; 'b. and b.' अचिरात्; अचिरेण, क्रमशः; शनैः शनैः; 'b. the b.' अपरंच; 'b. degrees' क्रमशः; 'b. hundreds' शतशः; 'one b. one' एकैकशः, आनुपूर्वेण; 'b. end' स्वार्थः, स्वहितं; 2 गौणार्थः. 'b. oneself' रहसि, निभृतं, रहः. 'b.-gone' अतीत, अतिक्रांत, गत; 'b.-path' विमार्गः, विपथः, उपमार्गः, गूढपथः; 'b.-law' उपव्यवस्था, उपविधिः; 'b.-name' उपाधिः; by-product,' s. गौण-फलं-उत्पन्नं-लाभः. 'b.-stander' पार्श्वस्थः, प्रेक्षकः, समीपस्थः; 'b. word' उपहासास्पदं. 2 जनोक्ति f. आभाणकः.

Byre, s. व्रजः, गोष्ठं, गोशाला.

C.

Cab, s. एकाश्ववाहन-शकटः; 'c. man,' *See* **Coachman.**

Cabal, s. गूढमंत्रणा, कुविचारणा.—v. i. निभृतं मन्त्र् 10 A, कुहार्थं संमिल् 6 P. **-ler,** s. कुमंत्रणकृत् m., गूढमंत्रिन् m., भेदकरः.

Cabala, s. गूढशास्त्रं, गुप्तविद्या. **-Cabalist,** s. गूढशास्त्रज्ञः. **-ic,** a. निगूढार्थ, गुप्तार्थ.

Cabbage, s. शाकं, हरितकं. 2 s. (सूचिकेन) मुषितं पटखंडं. —v. i. (सूचिकवत्) पटखंडं मुष् 9 P.

Cabin, s. कुटि-टी f., शाला, कोष्ठः. 2 नौकाभ्यंतरं कोष्ठः. 3 वेश्मन् n., कुटीरः. 4 Tent, q. v. **-et,** s. वेश्मन् n., कक्षांतरं, उपरोधकं. 2 शिष्टसभा, धीसचिवसभा; गूढमंत्रणं. 3 रत्नकोष्ठः. 4 समुद्गकः, संपुटः; *See* **Box.**

Cable, s. नौरज्जु f. 2 विद्युत्संदेशवाहकं तंत्रं. **-ed,** a. रज्जुबद्ध. **-gram,** विद्युत्संदेशः.

Cachexy, s. दोषत्रयं, त्रिदोषं, शरीरदोषः.

Cachination, s. अट्टहासः, प्रहासः.

Cackle, Cackling, s. कूजनं, हंसरुतं; अव्यक्तरवः. 2 जल्पितं, प्रलापः.—v. i. कूज् 1 P, अव्यक्तं रु 2 P. **-er,** s. कूजकः.

Cad, s. ग्राम्यजनः, असभ्यः.

Cadaverous, a. शवतुल्य, शवसवर्ण.

Caddie, s. संदेशहरः, दूतः.

Cadence, s. पातः, च्युति f. 2 स्वरः, विरावः, निन्हादः; स्वरसंक्रमः, स्वरावरोहः.

Cadet, s. अनुजः, अवरजः. 2 युद्धकर्माभ्यासिन् m.

Cadge, v. i. छद्मना जीविकां कृ 8 U. 2 शोषणपूर्वकं अल्पद्रव्यं विक्री 9 U. 3 *See* '**Beg.**'

-er, s. आपणिकः. विपणिकः, 2 छद्मजीविन् m.

Cafe', s. पानगृहं.

Cæsura, s. विच्छेदः, विरामः.

Cage, s. पंजरः-रं, पिंजरं, वीतंसः. 2 Prison, q. v. —v. t. पंजरे रुध् 7 U or बंध् 9 P.

Cairn, s. उपल-पाषाण-राशिः, शिलासमुच्चयः, प्रस्तरचिति f.

Caitiff, s. खलः, शठः, दुर्वृत्तः; *See* **Wicked.**

Cajole, v. t. लल् 10, उपच्छंद् 10. 2 **Cheat,** q. v. **-ry,** s. चाटूक्ति f. 2 वंचनं, छलं, &c.

Cake, s. पूपः, पिष्टकः, अपूपः. —v. i. पिंडीभू 1 P.

Calamity, s. विपद् f., आपद् f., व्यसनं, अनर्थः, उपप्लवः, दुःखं, संकटं, अत्याहितं. 2 उत्पातः, दैवी आपद्. **-ous,** a. विपद्ग्रस्त, व्यसनोपेत, विपदापन्न, दुर्गत, विधुर.

Calamus, s. वेत्रः, वेणुः.

Calash, s. केलिरथः, क्रीडायानं.

Calcareous, a. शार्करीय. 2 चूर्णमय-गुण.

Calcine, v. t. भस्मीकृ 8 U.

Calculate, v. t. गण् 10 परिसं-सं-ख्या 2 P, संकल् 10. 2 निरूप् 10; चिंत् 10, प्रकल्प् c. **-ed,** a. गणित, संख्येय. 2 युक्त, पर्याप्त, उचित, अलं with inf. **-ion,** s. गणने-ना, संख्यानं. **-or,** s. गणकः.

Calculous, a. शिला-अश्म-मय (यी f.)

Calculus, s. अश्मरी, मूत्रकृच्छ्रं.

Caldron, s. पिठरः-रं, उखा, कुंडं, स्थाली.

Calefy, v. t. तप् 1 P

Calendar, s. पंजी, पंजिका.

Calends, s. प्रतिपद् f.; प्रथमदिवसः.

Calf, s. गोवत्सः, वत्सः, तर्णकः. 2 जंघापिंडिका, पिंडिका.

Calibre, s. छिद्रं; छिद्रव्यासः. 2 परिमाणं. 3 प्रकारः, जाति f. 4 मेधा.

Calico, s. चित्रितकार्पासपटः.

Caligation, *See* **Darkness.**

Caligraphy, s. शोभनलेखनकला-शिल्पं.

Calisthenics, s. व्यायामः.

Calix, s. पुष्पगर्भः, पुष्पकोशः

Call, v. t. ह्वे 1 P, आह्वे, शब्दायति (D.), आकृ c. 2 अभिधा 3 U, आख्या 2 P, आह्वे, चक्ष् 2 A, नाम कृ 8 U; कृत् 10; 'c. ed her by the name of Parvati' तां पार्वतीति नाम्ना जुहाव (बंधुजनः) (K. I. 26), तस्याः पार्वतीति नाम चकार; वच् 2 P, उदाहृ 1 P, ब्रू 2 U. 3 नि-आ-मंत्र् 10 A; 'c. by name' नामग्राहमाह्वे, संबुध् c.; 'c. to mind' स्मृ 1 P, मनसि कृ 8 U; 'c. to account' किं किं कृतमिति प्रच्छ् 6 P or अनुयुज् 7 A or अनुसंधा 3 U; 'c. to witness' साक्षिणं कृ, समेत (अग्नि) साक्षाय विवाहकाले

(R. VII. 20). -s. आह्वानं; पृच्छा; निर्मंत्रणं, संबोधनं. 2 प्रयोजनं. 3 अभिगमः; नियोगः; ' I have many c. s upon me to-day ' मयाद्य कर्तव्या बहवो नियोगाः संति. -back, प्रत्यादिश् 6 P, निवृत् c.; खंड् 10, निरस् 4 P. -for, अर्ह् 1 P; ' this matter c. s for consideration ' अयमर्थो विचारणामर्हति; or अत्र विचारणया प्रयोजनं; अपेक्ष् 1 A. -forth, प्रोत्सह् c., उद्युज् 10; प्रकटीकृ, प्रकाश् c. -out, पट् 1 P; उत्क्रुश् 1 P. 2 तारस्वरेण. उच्चैः आह्वे, घुष् 10. -upon, on, अर्थ् 10 A, याच् 1 A. 2 द्रष्टुं व्रज् 1 P, अभिगम्. -up, (from sleep) प्रबुध् c. -ed, a. आहूत; 2 अभिहित, उक्त, उदाहृत; gen. ex. by नाम ind., नामन्, अभिधान, आख्या, अभिधा, संज्ञा, नामधेय, in comp.; ' a boy c. Rama, ' रामो नाम, रामनामा, रामसंज्ञः, &c. बालः. -ing, s. See (s.). 2 वृत्ति f., जीवनसाधनं, उपजीविका; व्यवसायः.

Calligraphy, *See* **Caligraphy.**

Callous, *a.* कठिन, घन. 2 कठोर, निर्दय, कर्कश; 'c. to contempt' तिरस्कारमगणयन्, तिरस्कारानभिज्ञः. 3 निर्लज्ज, धृष्ट; अविनीत. -ness, *s.* काठिन्यं, निर्दयता, &c. -Callosity, *s.* किणः, त्वग्दृढता.

Callow, *a.* अजातपक्ष, पक्षहीन. 2 *See* **Inexperienced.**

Calm, *a.* प्र-उप-शांत, निश्चल, प्रसन्न, स्तिमित, अनुत्तरंग, अक्षुब्ध, निष्कंप, निर्वात, अव्याकुल; ' to be c.' शम् 4 P, प्रसद् 1 P; ' heart, be c. ' हृदय प्रसीद, मा उत्ताम्य. -s. निर्वातः, शांति f.; प्रसादः, विश्रामः. 2 शांतता, स्तिमितता; ex. by (a.). -v. t. उप-प्र-शम् c. (शमयति), उप-परि-सांत्व् 10; तुष् c., प्रसद् c. 2 लघूकृ 8 U, अपनी 1 P. -ly, *adv.* निश्चलं, अक्षोभं, शांत्या, प्रशांतं. -ness, *s.* प्र-उप-शांति f., निर्विकारता, प्रसादः, अव्याकुलता, असंभ्रमः. 2 निर्वातत्वं, अक्षोभः, स्तिमितता.

Caloric, *s.* उष्णता, तापः.

Calorific, *a.* तापकर (री f.); तापजनक.

Calve, *v. i.* वत्सं सू 2 A; प्रजन् 4 A.

Calumniate, *v. t.* परि-अप-वद् 1 U; निर्भर्त्स् 10 A, निंद् 1 P, अपभाष् 1 A मिथ्या अभियुज् 7 A, 10; आ-अधि-क्षिप् 6 P. -or, *s.* परिवादरतः, परिवादिन् m., निंदकः, अभ्यसूयकः, अभिशापकः, पिशुनः, आक्षेपकः. -Calumny, *s.* परिवादः, पैशुन्यं, अभ्यसूया, अलीकप्रवादः, मिथ्याभिशापः, पिशुनवचनं, आक्षेपः, मिथ्याभियोगः. -ous, *a.* पिशुन, कलंकमय (यी f.). -ously, *adv.* सापवादं, परिवादेन, साभ्यसूयं.

Calx, *s.* चूर्णं, भस्मन् n. 2 रीतिपुष्पं.

Calyx, *s. See* **Calix.**

Cambric, *s.* अंशुकं, दुकूलं.

Camel, *s.* उष्ट्रः; क्रमेलकः, मयः, महांगः; ' young c. ' करभः; ' she-c. ' उष्ट्री.

Camisado, *s.* रात्रियुद्धं.

Camlet, *s.* ऊर्णावस्त्रं.

Camp, *s.* शिबिरं, निवेशनस्थानं, निवेशः. 2 सैन्यनिवासः. -v. t. सैन्यं निविश् c.

Campaign, *s.* समरभूमि f., -स्थलं. 2 युद्धकालः, युद्धप्रवृत्ति f.

Camphor, *s.* कर्पूरः-रं, घनसारः, सिताभ्रः, हिमवालुका, चंद्रः, सोमः. -ated, *a.* कर्पूरसंमिश्र-संसृष्ट.

Camus, *a.* चिपिट.

Can, *v. i.* शक् 5 P, प्रभू 1 P, or समर्थ-क्षम-शक्त a. भू with inf. of verb; *See* **Able,** oft. by ईश् 2 A; पृ 10. 2 In pass. ex. by pot. pass. part. ; ' c. be done ' करणीय a., कार्य, &c.; ' I cannot but go ' मयावश्यं गंतव्यमेव. -s. कंसः, भाजनं, धातुपात्रं, चषकः.

Canal, *s.* कुल्या, प्रणाली.

Canard, *s.* अश्रद्धेया कथा.

Cancel, *v. t.* अव-वि-लुप् 6 P or c., व्या-अप-निर्-मृज् 2 P; निरस् 4 P, खंड् 10, निवृत् c.

Cancer, *s.* कर्कटः, कर्कः. 2 कुलीरः. 3 मांसार्बुदं; सद्व्रणः, विस्फोटः. -ate, *v. i.* प्ररुह् 1 P.

Candent, *a. See* **Ho**

Candid, *a.* निष्कपट, निर्व्याज, सरल, स्फुट-स्पष्ट-वादिन्, ऋजु, निर्मल, शुद्धात्मन्, निर्व्यलीक; शुचि. -ly, *adv.* निष्कपटं; स्फुटं, निर्व्याजं. -ness, -Candour, *s.* निष्कापट्यं, निर्व्याजता, आर्जवं, सरलता, अमाया, दाक्षिण्यं निर्व्यलीकता, शौचं.

Candidate, *s.* अर्थिन् m., याचकः, प्रार्थकः, पदान्वेषिन् m.

Candify, *v. t.* धवलीकृ 8 U, शुक्लीकृ.

Candle, *s.* दीपः, दीपिका, वर्ति-र्ती f. -holder, *s.* दीपहस्तः-वाहः. -stick, *s.* दीपपादपः, दीपशिखा-वृक्षः.

Candy, *v. t.* घनी-खंडी-सांद्री-कृ 8 U, स्त्यै c. -v. i. स्त्यै 1 A, घनीभू 1 P. -s. शर्करा सितोपला, खंडमोदकः.

Cane, *s.* वेतसः, वेत्रः, वेणुः, वंशः, वानीरः. 2 वेत्रयष्टि f. -दंडः; ' sugar-c. ' इक्षुः; ' seat of c. ' वेत्रासनं; ' made of c. ' वैणव (वी f.), वैदल (ली f). -v. t. वेत्रेण तड् 10 or हन् 2 P or प्रहृ 1 P.

Canine, *a.* कुक्कुरीय, श्वन् in comp.

Canker, *s.* विद्रधिः, व्रणः. 2 फलनाशी कीटः. 3 कलंकः, विष. 3 दूषणं, विलयनं, विनाशः. -v. t. विनश् c., विली c., दुष् c. (दूषयति). -v. i. विली 4 A, दुष् 4 P

Cannibal, *s.* नृभुज् *m.*, पिशिताशः -शनः, पुरुषादः, क्रव्याशिन् *m.* **-ism,** *s.* क्रव्याशित्वं, &c.

Cannon, *s.* गुलिप्रक्षेपणी लोहनालिःली *f.* **-Ball,** *s.* आग्नेयास्त्रं, रणगुलि *f.*

Canoe, *s.* लघुनौका, उडुपं, प्लवः, कोलः.

Canon, *s.* विधिः, नियमः ; शास्त्रं. व्यवस्था. 2 पौरोहितधर्मशास्त्रं. 3 धर्मपुस्तकसंहिता. 4 (a ravine) जलप्रवाहकृतदरी. **-ical,** *a.* वैधिक (की *f.*), नियमानुसारिन्. **-ically,** *adv.* विधिवत्, यथाविधि,-शास्त्रं. **-ize,** *v. t.* सिद्धजनमध्ये आरुह् c. (रोपयति) or गण् 10 or संख्या 2 P.

Canopy, *s.* वितानं, उल्लोचः, आच्छादनं, पिधानं. *-v. t.* वितानीकृ 8 U, वितानेन आच्छद् 10.

Canorous, *a.* सुस्वर, मधुस्वन.

Cant, *s.* परिभाषा, कल्पितसंज्ञा. 2 अपभाषा. 3 वाक्छलं, दंभोक्ति *f.*, दांभिकवचनं. 4 प्रावण्यं. 5 उद्घोषणेन विक्रयः. *-v. i.* परिभाष् 1 A. 2 दांभिकतया वद् 1 P 3 अर्धवलितेन चल् 1 P. *v. t.* उद्घोषणेन विक्री 9 A. *a.* उत्साहिन्, तेजस्विन्. **-ation,** *s.* मार्गः, रीतिः. **-er,** *s.* अर्धवल्गितं. 2 दांभिकः, धर्मध्वजिन् *m.* **-icle,** *s.* उपगानं.

Cantankerous, *a.* दुराग्रह, दुर्दम, आग्रहिन्.

Cantharides, *s.* विस्फोटकीटकः.

Canthus, *s.* अपांगः- गं, नेत्रपर्यंतः.

Cantillate, *v. t.* or *v. i.* गै 1 P.

Cantle, Cantlet, *s.* खंडः, भागः.

Canto, *s.* सर्गः, पर्वन् *n.*, परिच्छेदः; अध्यायः; स्कंधः, (of different compositions).

Canton, *s.* चक्रं ; भूभागः, प्रदेशः. *-v. t.* खंडशो विभज् 1 P. 2 आवासं क्लृप् c. **-ment,** *s.* सैन्यावासः, शिबिरं.

Canty, *a.* उत्साहिन्, तेजस्विन्.

Canvas, *s.* शणवस्त्रं, शाणं, स्थूलपटः. 2 वातवस्त्रं.

Canvass, *v. t.* Beg, q. v. 2 परि-ईक्ष् 1 A, विचर् c., निरूप् 10 ; अनुसंधा 3 U. *-s.* स्थूलपटः, शाणं. 2 वातवस्त्रं. **-er,** *s.* मार्गकः.

Cap, *s.* शिरस्त्राणं, शिरस्कं, शिरोवस्त्रं, शिरोवेष्टनं. 2 अग्रं. *-v. t.* पिधा 3 U; *See* **Cover.** 2 अति-शी 2 A. 3 अग्रं आच्छद्. 10 *-v. i.* अभिवादनार्थं शिरस्त्राणमुन्मुच् 6 P or अवनम् c. or अपनी 1 P.

Capable, *a.* समर्थ, शक्त, क्षम, योग्य, उचित ; gen. ex. by शक्य with inf., or pot. pass. part.; ' c. of being defeated' पराजेतुं शक्यः, पराजेतव्यः, ' Râma is not c. of such atrocity ' नेदृशं नृशंसचरितं रामेण कर्तुं शक्यते, रामे संभाव्यते; ' c. person ' पात्रं, गुणवत्, ' to be c. ' प्रभू 5 P, उत्सह् 1 A, क्लृप् 1 A (with dat.) **-Capability,** *s.* सामर्थ्यं, शक्ति *f.*, पात्रता, योग्यता.

Capacious, *a.* विशाल, उरु, प्रभूत; *See* **Broad.** 2 विपुल, प्रचुर.

Capacitate, *v. t.* उपयुक्त-क्षम *a.* कृ 8 U.

Capacity, *s.* धारणशक्ति *f.*, ग्रहणसामर्थ्यं (lit. & fig.); ' c. for all knowledge अशेषविद्याग्रहणसामर्थ्यं. 2 बलं, शक्ति *f.*, सामर्थ्यं, पात्रता, योग्यता. 3 परिमाणं, विस्तारः. 4 (Relation) gen. ex. by वृत्ति or रूपेण; ' he served the king in the c. of a servant ' सेवकरूपेण राजानं सिषेवे, अवस्था, भावः, वृत्ति *f.*, विषयः; सेवकविषये सभवाधिकृतं (Mal. 1) ' employs me in the c. of a servant. '

Cap-a-pie, *adv.* नखशिखांतं, सर्वांगं.

Caparison, *s.* आस्तरणं; अश्वसज्जा-सज्जनं, अश्वालंकारा: (pl.). *-v. t.* विभूष् 10, अलंकारैर्भूष्.

Capcase, *s.* समुद्गकः, संपुटः.

Cape, *s.* भूशिरस् *n.*,अंतरीपः-पं. 2 स्कंधप्रावरणं, ग्रीवाप्रच्छदः.

Caper, *s.* *See* **Leap.**

Capillament, *s.* केशरः-रं, किंजल्कः.

Capillary, *a.* केशोपम; सूक्ष्म, केश in comp., ' c. attraction ' केशाकर्षणं.

Capital, *a.* श्रेष्ठ, परम, मुख्य, प्रधान, विशिष्ट, वरिष्ठ, उत्तम, उत्कृष्ट; ' c. punishment ' उत्तमसाहसं, देहदंडः, प्राणदंडः; ' c. crime ' वधार्हं पातकं; वधदंडार्हं पापं. *-s.* राजधानी. 2 मूलं, मूलद्रव्यं; 'floating or circulating c.' *s.* परिवर्तिन् *a.* मूलद्रव्यं. 'fixed c.' स्थायिन् *a.* मूलद्रव्यं; ' make c. out of,' हितं साध् c., हितानुकूल *a.*,कृ. 8U. 3 शीर्षं, अग्रं. **-ist,** *s.* द्रव्यवत् *m.*, कोटीश्वरः. **-ly,** *adv.* उत्तमसाहसेन, प्राणदंडेन. 2 परमं, श्लाघ्यप्रकारेण, विशिष्टतया.

Capitation, *s.* एकैकशः परिगणनं; जनसंख्या.

Capitulate, *v. i.* शत्रुहस्ते आत्मानं समर्पणं सम्-ऋ c. (अर्पयति), शत्रोरधीन *a.* भू, वशं गम् 1 P. 2 संक्षेपतः लिख् 6 P or कथ् 10. **-ion,** *s.* समयपूर्वकं समर्पणं; वशीभवनं, शत्रुकरार्पणं.

Caprice, *s.* कामचारः, चापल्यं, मनोलौल्यं; ' c. of fortune ' दैवविलसित-विजृंभितं; दैवस्य कामचारः (Mu. 2). **-Capricious,** *a.* कामचारिन्, चपल, चंचलप्रकृति, लोलचित्त, लोल, अस्थिर, स्वैरवृत्त, स्वैरिन्. **-ly,** *adv.* लोलचेतसा, चापल्येन, कामतः, स्वैरं, कामचारेण. **-ness,** *s.* चापल्यं, लोलता, कामचारिता, &c.

Capricorn, *s.* मकरराशिः, मकरः.

Capsize, *See* **Overturn.**

Capstan, *s.* चक्रयंत्रं.

Capsule, *s.* बीजकोषः, पुटः-टं. **-ar,** *a.* पुटाकार.

Captain, *s.* सेनानीः, गुल्मपतिः, दंडनायकः. **2** पोताध्यक्षः. **3** नायकः, नेतृ *m.*, मुख्यः, अग्र-पुरो-गः.

Captation, *s.* लोकरंजनं, जनश्लाघासेवनं.

Caption, *s.* निरोधः, आसेधः.

Captious, *a.* दोषैकदृश्, छिद्रान्वेषिन् विवादशील. **2** भ्रांतिकर (री *f.*). **-ly,** *adv.* विवादेच्छयैव, छिद्रान्वेषिवत्. **-ness,** *s.* छिद्रान्वेषिता; विवादशीलता.

Captivate, *v. t.* मुह् c., ग्रह् 9 P; हृ 1 P; विलुभ् c. (eye, ear, &c.); ' c. s the eye ' विलोभयति चक्षुः. **2** दासीकृ 8 U, बंदीकृ, वशीकृ, दम् c. (दमयति). **-ing,** *a.* मनोहर, चित्तहारिन्, मनोज्ञ, हृदयग्राहिन्, हारिन्, मोहिन्. **-ion,** *s.* बंदी-दासी-करणं &c.

Captive, *s.* बंदिः, बंदि *f.*, कारागुप्तः, made c. ' (taken prisoner) बंदीकृत, बंदिग्राहं गृहीत. **2** दासः. **-a.** बंदीकृत, दासीकृत, प्रग्रहक, कारास्थ. **-ity,** *s.* बंधनं, बंदित्वं, कारावासः. **2** दासत्वं, दासभावः.

Captor, *s.* जेतृ *m.*, बंदीकर्तृ *m.*

Capture, *v. t.* ग्रह् 9 P, बंदी-दासी-कृ 8 U; (a fort) भंज् 7 P, लंघ् 10, आक्रम् 1 U, 4 P. **-s.** ग्रहः, ग्रहणं; लोप्त्रं, लोत्रं; ' c. of a fort ' दुर्गलंघनं; ' c. of cattle ' गोग्रहः, धेनुहरणं.

Car, *s.* रथः, वहनं, चक्रयानं, प्रवहणं; ' heavenly c. ' विमानं; ' war c. ' स्यंदनः.

Caracole, *s.* तिर्यक्प्लुतं, वक्र-कुटिल-गति *f.* **-v. i.** तिर्यक् प्लु 1 A, or वल्ग् 1 U.

Caravan, *s.* सार्थः, संघः; ' leader of c. सार्थवाहः. **-sary,** *s.* पथिकावासः; पांथनिवासस्थानं.

Carbuncle, *s.* विस्फोटः; वल्मीकं. **2** पद्मरागः.

Carcanet, *s.* मुक्तावलि *f.*, मणिमाला.

Carcass, *s.* शवः-वं, कुणपः, मृतं शरीरं.

Card, *s.* पत्रं; क्रीडापत्रं. **2** ऊर्णामार्जनी. **-v. t.** ऊर्णां संमृज् 2 P or मृज् 1 P. **-er,** *s.* ऊर्णामार्जकः.

Cardamom, *s.* एला, निष्कुटि-टी *f.*, पृथ्वीका, चंद्रबाला, बहुला; ' small c. ' उपकुंचिका, तुत्था, कोरंगी, त्रिपुटा, त्रुटि-टी *f.*

Cardiac, *a.* तेजस्कर, दीपक, अग्निद्. **-s.** हृद्रोगः.

Cardinal, *a.* प्रधान; *See* **Capital,** *a.*; ' c. point ' दिग्भागः. **-s.** धर्माध्यक्षः.

Care, *s.* चिंता, औत्सुक्यं, उद्वेगः; *See* **Anxiety. 2** यत्नः, प्रयत्नः, आदरः, मनोयोगः; ' brought up with c. ' प्रयत्नसंवर्धितः, सादरं परिपालितः. **3** सूक्ष्मता, निपुणता; ' searching with c. ' निपुणमन्विष्य; ' thinking with c. ' सुनिपुणं विमृश्य. **4** रक्षा; अवेक्षा; 'leave under the c. of ' *See* **Charge. 5** अप्रमादः, सावधानता, अवधानं; ' have a c. what you do ' यत्कर्तव्यं तद्विमृश्य-समीक्ष्य-कुरुत. **-v. i.** अव-अप-ईक्ष् 1 A, चिंत् 10, मन्, धा 3 U, oft. ex. by the several nouns above; ' I do not c. now' अधुनाहं वीतचिंतः, 'I c. very much for your protection ' मम रक्षणे बलवान्प्रमादः. **2** गण् 10, (न तृणवदपि गणयति शत्रुं), आदृ 6 A (न त्वामाद्रियते), ईक्ष् 1 A, (the sense being clear). न कामवृत्तिर्वचनीयमीक्षते (K. V. 82) 'a self-willed person c. s not for blame '. **-'take c.'** रक्ष् 1 P, अव-ईक्ष् 1 A (अप्रमत्तो दुहितरमवेक्षस्व जानकीं U. 1), चिंत् 10 (ततस्त्वां चिंतयिष्यति). **2** लल् 10; पुष् c., पा c. (पालयति), त्रै 1 P. **3** अवहित-सावधान *a.* भू 1 P, अवधा 3 U, ' let c. be taken of each character ' प्रतिपात्रमाधीयतां यत्नः (S. 1), ' do not c. to think' सावधानेन चेतसा न विचारयति, इति विचारं नाद्रियते. **-ful,** *a.* Anxious, q. v. **2** अप्रमत्त, सावधान, अभियुक्त, अवहित, युक्त. **-fully,** *adv.* सावधानं, प्रयत्नतः, अवहितं, सादरं, निपुणं. **-less,** *a.* प्रमत्त, अनवधान, निरपेक्ष, निरवधान, असमीक्ष्यकारिन्, 'to be c. in ' प्रमद् 4 P (with abl.), स्वाधिकारात्प्रमत्तः (Me. 1.). **-lessly,** *adv.* प्रमादात्, अनवधानेन, &c.

Career, *s.* चर्या; धावनं. **2** गति *f.*, क्रमः, चलनं, चरितं; ' c. in life ' जीव-लोक-यात्रा; ' during his c. ' तस्मिन् (धुरं) धारयति. **-v. i.** वेगेन धाव् 1 P.

Caress, *v. t.* परामृश् 6 P, आलिंग् 1 P, परिरभ् 1 A; *See* **Clasp. 2** लल् 10. **-s.** परिरंभः-णं, लालनं, आलिंगनं, परिष्वंगः.

Caret, *s.* काकपदं, हंसपादाकृति चिह्नं.

Cargo, *s.* पोतभारः, पोतस्थं द्रव्य-भांडं.

Caricature, *s.* हासजनकं चित्रं, हास्यचित्रं. **-v. t.** चित्रेण हास्यास्पदं नी 1 P; हास्यजनकेन चित्र् 10. **-ist,** *s.* हास्यप्रतिमाकृत् *m.*

Cariole, Carriole, *s.* लघुशकटः, अश्वयुक्त *a.* यानं.

Carious, *a.* गलित, क्षीण, पूयपूर्ण. **-Caries, -Cariosity,** *s.* अस्थिक्षयः-शोषः.

Cark, *v. i.* चिंताकुल *a* भू 1 P.

Carle, *s.* दुर्वृत्तः; ग्राम्यः अविनीतः; *See* **Wicked.**

Carminative, *a.* वायुनाशिन्, अग्निद्, अग्निवर्धक.

Carmine, *s.* अरुणरंगः.

Carnage, *s.* वधः, विशसनं, संहारः, हत्या.

Carnal, *a.* कायिक-शारीरिक (की *f.*). 2 दैहिक (की *f.*). 3 विषयिन्, विषयासक्त, विषयोपसेविन्, 'c. pleasure' विषयसुखं; 'c. desires' विषयवासनाः; 'c. union' संभोगः, अभिगमः. **-ity,** *s.* विषयासक्ति *f.*, विषयोपसेवा, कामुकता. **-ly,** *adv.* कामुकवत्.

Carnation, *s.* मांसवर्णः; लोहितवर्णः.

Carnival, *s.* तुमुलोत्सवः.

Carnivorous, *a.* क्रव्याद्, मांसभुज्, पिशिताशन, क्रव्यभोजन.

Carnosity, *s.* गंडः; मेदोग्रंथिः.

Caroche, *s.* क्रीडारथः, चातुरं.

Carol, *s.* हर्ष-आनंद-गीतं. 2 स्तोत्रं, भक्तिगीतं. **-v.** *t.* हर्षेण गै 1 P, उपगै, स्तु 2 U.

Carouse, *v. i.* अतिपानं कृ 8 U, पानोत्सवं कृ, अतिपानेन क्षीब *a.* भू 1 P. **-s., -al,** *s.* अतिपानं, पानोत्सवः. **-ver,** *s.* पानरतः, अतिपायिन् *m.*

Carp, *s.* शफरि, प्रोष्ठः-ष्ठी. **-v.** *i.* (at) छिद्रं अन्विष् 4 P; दोषं दृश् 1 P or निरूप् 10, निंद् 1 P; *See* **Censure. -er,** *s.* छिद्रान्वेषिन् *m.*, दोषैकदृश् *m.* **-ing,** *s.* गर्हा, निंदा, छिद्रान्वेषः.

Carpenter, *s.* तक्षकः, सूत्रधारः, रथकारः, स्थपतिः, त्वष्टृ *m.*, तक्षन् *m.* **-Carpentry,** *s.* दारुकर्मन् *n.*, तक्षकक्रिया, तक्षशिल्पं.

Carpet, *s.* कुथः-था, आस्तरणं; 'brought on the c.' प्रस्तुत, उपक्षिप्त.

Carrion, *s.* पूतिमांसं, अखाद्यमांसं; कुणपः. **-eater,** *s.* कुणपभुज् *m.*

Carry, *v. t.* वह् 1 P, नी 1 P, भृ 3 U, हृ 1 P. 'c. ed a dog on his shoulder' स्कंधेन श्वानमुवाह. 2 साध् 5 P or c.; 'c. a fort' दुर्गं लंघ् 1 A, 10 or भंज् 7 P, or वशीकृ 8 U; 'the enemy c. ed the day' शत्रवो जयमापुः; 'c. one's point' अभीष्टं लभ् 1 A, प्रतिज्ञां पूर् 10, 'c. oneself' आचर् 1 P, *See* **Act,** 'c. arms' शस्त्राणि ग्रह् 9 P, सैनिकवृत्तिं आस्था 1 A. **-away, -off,** अपवह्, अपनी, अपहृ ; अपकृष् 1 U, अपकृष् 1 P. **-on,** प्रवृत् c., प्रणिधा 3 U. 'c. on war' युद्धं-संग्रामं कृ, विग्रहं ग्रह् 9 P. **-out,** अनुष्ठा 1 P. कृ 8 U, साध् 5 P or c. **-through,** पारं नी 'c. ing through all difficulties' आपदां पारं नयनं. **-Carriage,** *s.* वाहनं, यानं, रथः, प्रवहणं, शकटः-टं ; 'closed c.' कर्णीरथः, प्रवहणं, डयनं ; 'c. road' रथ्या; 'c. horse' रथ्यः. 2 आचरणं. व्यवहारः, गति *f.*, चरितं, चेष्टा. 3 निर्वाहः. प्रणयनं. **-Carrier,** *s.* वाहकः, हरः. in comp. 2 भांडवाहनजीविन् *m.*

Cart, *s.* शकटः-टं, शकटिका, वाहनं, प्रवहणं, यानं. **-v.** *t.* शकटेन वह् 1 P 2 शकटे निधा 3 U. 'Carter,' 'c. man' शाकटिकः, शकटवाहः, 'c. horse' शकटवाहनः ; धुर्यः धुरीणः; 'c. load' शाकटं, शलाटः, शकटभरः; 'c. rut' शकटचिह्नं-पद्धती-पद्धति *f.*; 'c. wright' शकटकारः. 'To put the c. before the horse,' विपर्यस् 4 P, विपर्यासं की 1 P.

Carte, *s.* भोजनपत्रिका. 'c. blanche,' अनिर्दिष्टसमय *a.* पत्रं.

Cartel, *s.* युद्धाह्वानपत्रं.

Cartilage, *s.* कोमलास्थि *n.* **-Cartilaginous,** *a.* तरुणास्थिविशिष्ट.

Carto-graphy, *s.* भूम्यालेख्य-कला-युक्तिः *f.*

Cartoon, *s.* चित्रितपटः, विचित्रमालेख्यं, हास्योत्पादकं चित्रं.

Caruncle, *s.* गंडः, मांसपिंडः.

Carus, *s.* निःसंज्ञता.

Carve, *v. t.* कृ 6 P, तक्ष् 1, 5 P, उत्कृ, (उत्कीर्णा इव वासयष्टिषु V. 3); उल्लिख् 6 P. 2 कृत् 6 P, छिद् 7 P, कृप् c., विभज् 1 U; 'c. out (a plan)' युज् 10; प्रक्लृप् c.; प्रतियुज् 10; चिंत् 10, निरूप् 10 **-er,** *s.* तक्षकः, कारुः, त्वष्टृ *m.*, तष्टृ *m.*, 2 परिकल्पकः.

Cascade, *s.* प्रपातः, प्रस्रवणं, वारिप्रवाहः, निर्झरः, उत्सः.

Case, *s.* अवस्था, भावः, दशा, स्थिति *f.*, वृत्ति *f.*: 'what is the c. with him' किं तस्य वृत्तं. 2 पर्दं. 3 अर्थः. 4 कार्यं, पक्षः. 5 पुटः, पिधानं, कोषः, आवेष्टनं. 6 भांडं, आधारः. 7 स्थानं, स्थलं. 'In c.' यदि चेत्; 'this being the c.' इयं सति-भते; 'in this c.' अत्र, अत्र विषये; 'in the c. of' gen. ex. by gen., or विषये in comp.; 'in the c. before us,' 'in the present c.' प्रस्तुतविषये, प्रकृते 'if such be the c.' यद्येवं, तेन हि; 'in both c. s' उभयथा, उभयपक्षे. **-v.** *t.* भांडे निधा 3 U or निधिक्षिप् c. 2 पिधा 3 U, अवृ 5 U

Casement, *s.* गवाक्षः, वातायनं, जालं.

Cash, *s.* टंकः मुद्रा. नाणकं **-keeper, -ier,** *s.* टंक धीशः रक्षकः. 'c.' सधन *a.* 'Out of c.' निर्धन *a.*

Cashier, *v. t.* अधिकाराद् भ्रंश् c. or च्यु c. or निरा-कृ 8 U or अपास् 4 P.

Cask, *s.* भांड, भाजनं, पात्रं

Casket, *s.* समुद्गकः, भांडं, मंजूषा, करंडकः, संपुटः-टकः.

Casque, *s.* शिरस्त्राणं, शिरस्कं

Cast, *v. t.* क्षिप् 6 P, प्र क्षिप्; अस् 4 P, मुच्-सृज् 6 P, पत् c. 2 (about) विचर् 10, आकल् 10, चिंत् 10 वि-तर्क् c. 3 विलाप्य संधा 3 U; 'c. glance' दृशौ क्षिप्, दृष्टिं-चक्षुः &c. दा 3 P. (दूरं तस्य वृषचक्षुः S. I) 'c. skin' कंचुकं विमुच्; 'c. lots'

कुक्षिप्त वद् c.; 'why c. pearls before swine' किमिदमर्क सारदूकराणां. —s. क्षेपः; पातः. 2 मूर्ति *f.*; वदन-ना; 'c. of characters' भूमिकासंविभागः. **—aside,** अपाकृ 8 U, निराकृ. **—away,** अपास्, परित्यज्, उत्क्षिप्. **—down,** अव-वि-सद् 1 P, म्लै 1 P; विषण्ण *a.* भू 1 P; 'with a face c.' खिन्न-विषण्ण वदनः; 'c. look' अधोदृष्टि *f.* 2 निपत् c., अधः क्षिप्. **—forth,** उत्सृज्, उद्गम् 1 P, उद्वृ 6 P. **—off,** विमुच्; अप-निर्-अस्. **—out,** अपाकृ, निःसृ c., निष्क्रम् c., प्रत्यादिश् 6 P. **—away,** *s.* त्यागः; अपाक्षेपः. **—ling,** *s.* गर्भपतितः, गर्भच्युतः.

Caste, *s.* वर्णः, जाति *f.*, कुलं; 'of the same c.' सवर्णः; 'low c.' हीनवर्णः, नीचः, निकृष्टजातिः; 'high c.' उत्तमवर्णः; 'mixture of c.s' वर्णसंकरः; 'low c. man' अंत्यजः; 'loss of c.' जातिभ्रंशः; 'out of c.' अपसदः, चांडालः, जातिहीनः; 'c. man' सजातीयः.

Castigate, *v. t.* दंड् 10; तड् 10. **—ion,** *s.* कशाघातः, शरीरप्रहारः; दंडः, निग्रहः.

Castle, *s.* दुर्गं, कोटः, 'c. in the air (in Spain), मनोराज्यं. **—Castellan,** *s.* दुर्गाधिपतिः. **—Castellated,** *a.* दुर्गाकार.

Castor-oil, *s.* एरंडतैलं.

Castrate, *v. t.* वृषणौ कृत् 6 P or उत्पट् 10 or छिद् 7 P. **—ed,** *a.* छिन्नमुष्क, निर्वृषण. **—ion,** *s.* मुष्क-वृषण-छेदः, पुंस्त्वहरणं.

Castrel, *s.* श्येनः.

Casual, *a.* अतर्कित, अचिंतित; आकस्मिक-आपातिक-आगंतुक-दैविक (की *f.*), दैवायत्त. **—ly,** *adv.* अचिंतितं, दैवात्, समापत्त्या, दैवयोगात्. **—ty,** *s.* दैवयोगः-घटना, संगति *f.* समापत्ति *f.* 2 अदृष्टं, आकस्मिकी आपद्. **—ties,** युद्धे हताः.

Casuist, *s.* धर्माधर्मविचारकः. **—ry,** *s.* धर्माधर्मविचारणा. 2 विवेचनविद्या 3 वितंडवादः.

Cat, *s.* मार्जारः, बिडालः, ओतुः, आखुभुज् *m.* 'c. a. (o)' mountain,' वनमार्जारः. 2 चित्रव्याघ्रः. 'c. eyed' तिमिरदर्शिन् *a.* **—ling,** *s.* मार्जारशावकः; 'c.'s paw मंदमतिः; (fig.) दुःखमर्ताष; *a.* 'c. witted' *a.* साधुपटुत; 'it rained c.s and dogs,' अतिधाराभिर्ववृषे. **'cat o' nine-tails'** नवरज्जुयुक्ता चर्मयष्टि *f.*, or कशा or ताडनी.

Cataclysm, *s.* पृथ्वीप्लावः, भूतसंप्लवः. 2 राज्यपरिवृत्ति *f.*

Catacomb, *s.* अंतर्भौमं, श्मशानं.

Catalepsis, } *s.* अपस्मारः; महामयः.
Catalepsy, }

Catalogue, *s.* परिसंख्या, परिगणना; 'c. of names' नामावलि-ली *f.*

Cataplasm, *s.* प्रलेपः, उपनाहः.

Catapult, *s.* गोफणा.

Cataract, *s.* निर्झरः, प्रपातः, प्रस्रवणं, उत्सः. 2 नेत्रपटलं, मंथः, शुक्रः; काचः.

Catarrh, *s.* अभिष्यंदः. 2 श्लेष्मन् *m.*, कफः, (variety of c.). **—al, ous,** *a.* अभिष्यंदिन्-कफिन्, श्लेष्मल.

Catastrophe, *s.* परिणामः, निर्वाहः, निर्वहणं. 2 आपद् *f.*; *See* **Calamity.**

Catch, *v. t.* धृ 1 P, 10, ग्रह् 9 P, बंध् 9 P (in a net &c.). 2 परामृश् 6 P, अवलंब् 1 A. 3 प्रलुभ् c., आकृष्-हृ 1 P; 'the house caught fire' ज्वलनमुपगतं-अग्निदीप्तं-गेहं; 'caught cold' शीताकुलो बभूव, पीनसोपहतः, अभिष्यंदाकुलः; 'c. in the act' (red-handed) कर्मगृहीत, सलोप्त्रग्राहित, लोप्त्रेण गृहीतः; 'Sir, you are c.' भो निगृहीतोऽसि (U. 4); 'c. in his own words' स्ववचनेनैव गृहीतः-निरुत्तरीकृतः. **—at,** अवलंब् 1A, आश्रि 1 U. **—up,** अपहृ 1 P, अपनी 1 P. **—***s.* तालकं. 2 लाभः, फलं. 3 पर्यायगीतं. **—er,** *s.* ग्राहकः, जालिकः. 2 वागुरा, जालं. **—ing,** *a.* संपर्किन्, संचारक 2 हारिन्.

Catchpole, *s.* दंड-यष्टि-धरः; राजपुरुषः.

Catechism, *s.* प्रश्नोत्तरं, सप्रश्नोत्तरः पाठः. **—Catechize,** *v. t.* प्रश्नोत्तरद्वारेण-क्रमेण-अधि-इ c. (अध्यापयति) or उपदिश् 6 P or प्रच्छ् 6 P. **—Catechist, —Catechiser,** *s.* प्रश्नोत्तरविधिना अध्यापकः-पाठकः.

Catechu, *s.* खदिरसारः.

Catechumen, *s.* नवशिष्यः-छात्रः.

Category, *s.* पदार्थः. 2 समानवर्गः, अधिकरणं. **—ical,** *a.* सुव्यक्त, स्पष्टार्थ; नियत, व्यक्त. **—ically,** *adv.* स्पष्टं, सुव्यक्तं.

Catenation, *s.* संबंधः अन्वयः, परस्परान्वयः. 2 शृंखलात्वं, दामता; परंपरा.

Cater, *v. i.* भोजनादि परि-उप-कल्प् c.

Caterpillar, *s.* कोषकारः शालिन् *m.*

Cates, *s.* स्वाद्वन्नं, विशिष्टान्नं.

Catgut, *s.* पुरीतत् निर्मिता तंत्री, तंतु *m.*

Cathartic, *s.* रेचकं, रेचनं, उदरशोधनं.

Cathedral, *s.* महामंदिरं, महती पूजाशाला.

Catholic, *a.* सर्वसामान्य, साधारण (णी *f.*), सार्वलौकिक (की *f.*). **—ism,** *s.* साधारण्यं, सार्वलौकिकता.

Cattle, *s.* गावः (pl.); गोकुलं, पशुसमूहः, गोव्रजः; 'c. for draught' धुर्यः, धुरीणः; 'keeper of c.' गोपालः, पशुपालः.

Caudal, *s.* लांगुलीय.

Caul, *s.* शिरोवेष्टनं. 2 अंत्रावेष्टनं. 3 गर्भवेष्टनं.

Cauldron, *s.* *See* **Caldron.**

Cause, *s.* कारणं, (oft. with loc. of effect, दैवं तृणां वृद्धौ कारणं), निदानं, बीजं, हेतुः, निमित्तं, मूलं, योनि *f.* 2 कार्यं प्रयोजनं. 3 स्थानं, अवसरः, पदं. 4 उत्पादकः

प्रयोजनं. 3 अर्थः पक्षः, कार्यं; 'material c.' समवायिकारणं; उपादानकारणं,प्रकृतिः; 'efficient (instrumental) c.' निमित्तकारणं; 'primary c.' बीजं, मूल-कारणं. -v. t. Ex. by causal of verbs; 'c. to fall' पातयति; गमयति, &c. 2 उत्पद् c., जन् c. (जनयति); कृ 8 U; oft. ex. by dat. of nouns with or without भू, अस्; यतस्ते स्वल्पदुःखाय (भवतः) (P. I. 1); *See* **Tend** (to): also ex. by संभव, जन्य, ज, in comp.; स्मरजा पीडा 'torment c. ed by Cupid', &c. **-al**, *a.* हेतुक, हेतुमत्. **-s.** णिच् (of verbs). **-ation**, *s.* कारणत्वं, हेतुता. **-ative**, *a.* उत्पादक, जनयितृ. **-er**, *s.* कारकः, उत्पादकः, प्रवर्तकः. **-less**, *a.* अकारण, निष्कारण, निर्निमित्त, and sim. comps. **-lessly**, *adv.* अकारणं, अहेतुकं, निर्निमित्तं, निष्प्रयोजनं.

Causerie, *s.* वार्ता, जल्पवादः.

Causeway, *s.* सेतुः, धरणं.

Caustic, *a.* दाहक, तिग्म, प्रखर 2 अरुंतुद, मर्म-स्पृश्-छिद्.

Cauterize, *v. t.* दह् c. **-Cautery**, *s.* दाहः; तप्तलोहेन मांसदाहः.

Caution, *s.* दक्षता, सावधानता, अप्रमादः, समीक्षा, अवेक्षा, अवधानं. 2 प्रातिभाव्यं, आधिः. 3 प्रत्यादेशनं, प्राक् सूचना or उपदेशः, प्राक् प्रबोधनं. **-v. t.** प्राक् सूच् 10; प्रत्यादिश् 6 P, प्राक् प्रबुध् c.; 'c. ed me against the approaching danger' उपस्थितापद्विषये सावधानो भव इति मामुपादिशत्. **-Cautious**, *a.* सावधान,दक्ष, अप्रमत्तः, समीक्ष्य विमृश्य-कारिन्, अवहित. **-ly**, *adv.* सावधानं, अवेक्षया, &c. **-ness**, *s.* अप्रमादः, दक्षता.

Cavalcade, *s.* सादियात्रा, अश्वारोहश्रेणी.

Cavalier, *s.* अश्वारोहः, सादिन् *m.*, तुरगिन् *m.*; 'to treat c. ly' अवमन् 4 A, सावलेपं अवज्ञा 9 U. **-C. s**, **-Cavalry**, *s.* तुरगबलं; अश्वारोहवर्गः, आश्विकं, सादिगणः.

Cave, **Cavern**, *s.* गुहा, दरी, गह्वरं, कंदरः-रा, विवरः-रं.

Caveat, *s.* प्राक्सूचनं; निषेधः

Cavil, *v. i.* मिथ्या निंद् 1 P; दोषं ग्रह् 9 P; छिद्रं अन्विष् 4 P; मिथ्या विवद् 1 A; मिथ्या अभियुज् 7 A, 10. **-s.** विवादः. वाग्युद्धं, मिथ्याविवादः, विप्रतिपत्ति *f.*; मिथ्याभियोगः. **-ler**, *s.* विवादशीलः. **-ling**, *a.* अपवादक, दोषग्राहिन्, छिद्रान्वेषिन्.

Cavity, *s.* रंध्रं, छिद्रं, विवरं, बिलं, खातं. 2 पुटः-टं; खं; 'c. of hands' अंजलिपुटः.

Cease, *v. i.* विरम् 1 P, निवृत् 1 A, विश्रम् 4 P, (with abl.); शम् 4 P, प्र-उप°; 'this said, he c. ed' इत्युक्त्वोपशशाम; 'c. ed to be opulent' निर्धनोभूत्; 'c. to exist' लय-क्षयं-या 1 P, नश् 4 P. 3 गम्, वि-अप-निर्-°, अपया 2 P. **-v. t.** (c.) of roots above. **-ing**, **-Cessation**, *s.* विरामः, उप-प्र-शमः, निवृत्ति *f.*, विरति *f.*, विच्छेदः. **-less**, *a* अनवरत, निरंतर, सतत, नित्य; अविच्छिन्न. **-lessly**, *adv.* निरंतरं, अनवरतं, नित्यं, &c.

Cecity, *s.* अंधता, तिमिरं.

Cedar, *s.* देवदारुः.

Cede, *v. t.* उत्सृज् 6 P, दा 3 U, विसृज् 1 P, परित्यज् 1 P. 2 अभ्युपगम् 1 P, वशं या 2 P. **-Cession**, *s.* प्रदानं, वितरणं, विसर्जनं.

Cedrate, *s.* *See* **Citron**.

Ceiling, *s.* वितानं, अंतःपटलं, पटलं, अंतश्छादनं.

Celebrate, *v. t.* प्रशंस् 1 P, उपवै 2 P, स्तु 2 U, कृत् 10, प्रथ् 10, प्रख्या c. (ख्यापयति), वर्ण् 10. 2 (As a ceremony) यथाविधि अनुष्ठा 1 P; पा c. (पालयति), आचर् 1 P, अभिनंद् c. (महोत्सवेन अग्रजन्माभिनंदितवान् Ka. 137); निर्वृत् c. (प्रस्थानकौतुकं निर्वर्तयितुं S. 4), निर्वह् c. **-ed**, *a.* प्रथित, वि-प्रख्यात, प्रसिद्ध, विश्रुत; लब्धवर्ण. 2 अनुष्ठित; 'c. in song' उपगीत. **-ion**, *s.* अनुष्ठानं, पालनं, &c. 2 स्तुति *f.*, वर्णनं, कीर्तनं, प्रशंसा. **-Celebrity**, *s.* यशस् *n.*; कीर्ति-ख्याति-विश्रुति-प्रसिद्धि *f.*, प्रतिष्ठा.

Celerity, *s.* वेगः, जवः, त्वरा.

Celestial, *a.* दिव्य, अमर्त्य, स्वर्गीय, दिविज; 'c. world' स्वर्लोकः; द्यो *f.*, 'c. damsel' अप्सरस् *f.* 2 (fig.) परम, उत्कृष्ट.

Celibacy, *s.* अनुद्वाहः, अदारपरिग्रहः, अविवाहः; 'he led a life of c.' अकृतदारः स आयुरत्यवाहयत्.

Cell, *s.* बिलं, रंध्रं, छिद्रं. 2 कुटी, कक्षः-क्षा, कुटीरः. 3 मठः, आश्रमः. **-Cellular**, *a.* सुक्ष्मरंध्रपूर्ण.

Cellar, *s.* भूमिगृहं, सुरंग *f.*

Celsitude, *s.* *See* **Height**.

Cement, *s.* लेपः, सुधा. 2 बंधनं, दृढीकरणं, संधिः. **-v. t.** संश्लिष् c., संधा 3 U, संयुज् 10. **-ation**, *s.* संयोगः, संश्लेषः, संधानं.

Cemetery, *s.* श्मशानं, परेतभूमि *f.*, पितृकाननं-वनं, प्रेतावासः.

Cenotaph, *s.* चैत्यं.

Cense, *v. t.* धूपं अर्प् 10. **-er**, *s.* धूपपात्रं-भाजनं.

Censor, *s.* गुणदोषविवेचकः, पापापापविवेक्तृ *m.* 2 दंडप्रणेतृ *m.*, नीतिशास्तृ *m.* **-Censorious**, *a.* दोषैकदृश्, अपवादक, निंदक; दोषदर्शिन्, निंदाशील. **-ly**, *adv.* सापवादं, निंदापूर्वकं. **-ness**, *s.* निंदा, छिद्रान्वेषिता, अपवादप्रियता.

Censure, *v. t.* निंद् 1 P, उपालभ् 1 A, निर्भर्त्स् 10 A, गर्ह् 1, 10 A, परि-अप-वद् 1 U, धिक्कृ 8 U, तिरस्कृ, दुष् c. (दूषयति), आ-अधि-क्षिप् 6 P; कुत्स् 10. —*s.* निंदा, उपालंभः, निर्भर्त्सना, गर्हणं, निर्वादः, वाच्यता, वचनीयता, अप-परी-वादः, आक्षेपः. **—able,** *a.* निंद्य, उपालभ्य, गर्हणीय, वाच्य, &c. **—er,** *s.* निंदकः, उपालंभकः, अप-परि-वादकः, आक्षेपकः.

Census, *s.* लोकपरिगणना, जनगणना.

Cent, *s.* शतं; '3 per c.' त्रिकं शतं; पंचकं शतं वृद्धिर्देया 'interest at 5 per c.' **—Centenarian,** *s.* शतायुस् *m.* **—Centenary,** *s.* शतकं, शतं. —*a.* शतक, शत्य. **—Centennial,** *a.* शताब्द, शतवर्ष. **—Centesimal,** *a.* शततम (मी *f.*). **—Centipede,** *s.* शतपदी, कर्णजलौकस्. **—Centuple,** *s.* शतगुणः. **—Centuplicate,** *v. t.* शतगुणीकृ 8 U. **—Century,** *s.* वर्षशतं, शतवर्षं. 2 शतं, शतकं. **—Centurian,** *s.* योधशताधीशः.

Centinel, *s. See* **Sentinel.**

Centre, *s.* मध्यः-ध्यं, मध्यभागः. 2 उदरं, गर्भः. 3 केंद्रं. —*v. t.* एकत्र कृ 8 U, समाहृ 1 P. —*v. i.* संमिल् 6 P, सं-इ 2 P, एकत्र समागम् 1 P, एकीभू; 'all eyes were c-ed on him' नेत्रव्रजास्तस्मिन्निपेतुः (R. vi 7); त्वयि तु परिसमाप्तं बंधुकृत्यं प्रजानाम् (S. 5); 'is c-ed in you' &c. 2 आश्रि 1 U, आ-अव-लंब् 1 A. **—Central, —Centrical,** *a.* मध्य, मध्यम, मध्यस्थ, मध्यगत, मध्यवर्तिन्. **—ly,** *adv.* मध्ये, मध्यस्थाने. **—Centrifugal,** *a.* मध्योत्सारिन्. **—Centripetal,** *a.* मध्यगामिन्.

Cephalalgy, *s.* शिरोवेदना.

Cerated, *a.* सिक्थलिप्त, सिक्थमय (यी *f.*).

Cerebrum, *s.* मस्तिष्कं, गोर्दं. **—Cerebral,** *a.* मस्तिष्कसंबंधिन्.

Cerecloth, Cerement, *s.* सिक्थाक्तं वस्त्रं.

Ceremony, *s.* विधिः, संस्कारः; 'marriage c.' परिणयविधिः. 2 नियमः, आह्निकाचारः, नित्यकर्मन् *n.*, नित्यकृत्यं; 'c. es of religion' वर्णाश्रमधर्मः (as opposed to शाश्वतधर्मः); 'occasional c.' नैमित्तिकं कर्मन् *n.* 3 शिष्टाचारः, सभ्याचारविधिः. **—al,** *a.* वैधिक-नैयमिक-व्यावहारिक (की *f.*). —*s.* व्यवहारः, आचारः, विधिः, नियमः &c.; 'sacrificial c.' यज्ञकर्मन् *n* इष्टि *f.* **—ous,** *a.* अतिसभ्य, अत्यादरयुक्त, अत्यादृत, अत्यनुनयिन्. **—ously,** *adv.* परमादरेण, अतिप्रश्रयेण, सप्रश्रयं, सादरं. **—ousness,** *s.* अत्यादरः, अतिसौजन्यं, अतिप्रश्रयः.

Certain, *a.* Ex. by चित्-चन and अपि with forms of किं. 2 निश्चित, ध्रुव, असंदिग्ध, असंशय, निःसंशय; अवश्य, नियत; 'I feel c.' इति मे निश्चयः, ध्रुवं मन्ये, 'it is c.' नात्र संशयः, नूनं, खलु. 3 अमोघ, अविफल, अवंध्य. 4 सविशेष, विशिष्ट. **—ly,** *adv.* (for c.) नियतं, ध्रुवं, खलु, असंशयं, नूनं, नाम; 'oh c.' (as a reply), अथ किं, कः संदेहः, कोऽत्र संशयः. **—ness, —ty, —Certitude,** *s.* ध्रुवत्वं, ध्रुवं, निश्चयः, असंशयः, निर्णयः, नियमः; 'leaves c. es' ध्रुवाणि परित्यजति.

Certes, *adv. See* **Certainly.**

Certify, *v. t.* विज्ञा c. (ज्ञापयति). 2 प्रमाणीकृ 8 U, सप्रमाणं कथ् 10; दृढीकृ. **—Certificate,** *s.* प्रमाण-निर्णय-पत्रं, आगमः, आगमपत्रं, निदर्शनपत्रं.

Cerulean, *a.* नील, आकाशवर्ण.

Cerumen, *s.* कर्णमलं, तोक्मं.

Cervical, *a.* ग्रैवेय.

Cess, *s.* करः, शुल्कं, राजस्वं. —*v. t.* राजस्वं दा c. or ग्रह् 9 P.

Cessation, *s. See* under **Cease.**

Cession, *s. See* under **Cede.**

Cesspool, *s.* दूषितजलकुंडं.

Chafe, *v. i.* प्रकुप्-क्रुध्-रुष् 4 P, संतप् pass., क्षोभं या 2 P, क्षुभ् 4 P, 1 A. —*v. t.* बाध् 1 A. प्रकुप् c., संतप् c., क्षुभ् c. 2 निर्घृष् 1 P, घर्षणेन तप् c. —*s.* रोषः, मन्युः, क्षोभः, प्रकोपः.

Chaff, *s.* तुषः, बुसं-सं, कडंगरः. **—less,** *a.* निस्तुष. **—y,** *a.* बुसमय (यी *f.*).

Chaffer, *v. i.* पण् 1 A, क्रयविक्रयं कृ. 8 U, व्यवहृ 1 P.

Chagrin, *v. t.* उद्विज् c., संतप् c., क्लिश् 9 P, व्यथ् c. (व्यथयति). —*s.* मन्युः, व्यथा, संतापः, क्लेशः.

Chain, *s.* शृंखला-लं, निगडः, बंधनं (lit. and fig.); 'a golden c.' कनकसूत्रं. 2 परंपरा, पंक्ति *f.*, श्रेणी, माला; 'c. work' शृंखलारूपं विरलकर्म. —*v. t.* निगडेन-शृंखलया-बंध् 9 P, निगडयति (D.). **—ed,** *a.* निगडित, शृंखलानिबद्ध, संयत, संदानित.

Chair, *s.* विष्टरः, आसनं, पीठं; 'arm c.' आसंदी. **—man,** *s.* अध्यक्षः, सभापतिः, नायकः.

Chaise, *s.* रथः, यानं, वाहनं.

Chaldron, *s. See* **Caldron.**

Chalice, *s.* पात्रं, भाजनं, शरावः, कंसः.

Chalk, *s.* कठिनी, खटि(टि)का, शुक्लशिलाधातुः, सितोपलः; 'red c.' गैरेयं, शिलाजतु *n.* —*v. t.* (out) निर्दिश् 6 P, प्रकाश् c., चिंत् 10, निरूप् 10. 2 (lit.) कठिनीखंडेन लिख् 6 P.

Challenge, *v. t.* घुष् 5 P, आह्वे 1 A, युद्धार्थं आहृ c., प्रत्यर्थ् 10 A, स्पर्ध् 1 A. 2 अभियुज् 7 A, 10, दोषं ग्रह् 9 P; निषिध् 1 P. —*s.* आह्वानं, समराह्वानं, अभियोगः. **—er,** *s.* समाह्वातृ *m.*, अभियोक्तृ *m.*

Chalybeate, *a.* लोहसंयुक्त, अयोगुणविशिष्ट.

Chamber, *s.* कोष्ठः, शाला, आगारं, आवासः, कक्षः, वेश्मन् *n.*; 'bed-c.' शय्यावेश्मन् *n.*, शयनागारं, वासगृहं; 'inner c.' कक्षांतरं, उपरोधकं; 'upper c.' चंद्रशाला शिरोगृहं. **-lain,** *s.* कंचुकिन् *m.*; शयनाधिकृतः, अंतःपुरवर्तिन् *m.*, महत्तरः; 'female c.' महत्तरिका. **-maid,** *s.* शयनपरिचारिका, अंतःपुरदासी.

Chameleon, *s.* कृकलासः, सरटः.

Chamois, *s.* वातप्रमीः. 'C. leather' मृदुचर्मन् *n.*

Champ, *v. t.* चर्व् 1 P, परि-सं-दंश् 1 P.

Champaign, *a.* सम. 2 अनावृत. -*s.* अनावृतसम-भूमि *f.*

Champion, *s.* योधः, वीरः, विक्रांतः, भटः. 2 रक्षकः, रक्षितृ *m.*, गोप्तृ *m.*

Chance, *s.* दैवं, दैवयोगः-घटना-गति *f.* 2 संशयः, संदेहपद-वस्तु *n.*; 'try your c.' आत्मनो दैवपरीक्षणं कुरु; 'to try the c. of a battle' रणसंशये आत्मानं पातयितुं; 'birth in a noble family is the work of c.' दैवायत्तं कुले जन्म (Ve.3); 'depending on c.' दैवपरः, यदृच्छिकः; 'by c.' दैवात्, दैववशात्-योगात्, अकस्मात्, असमर्थितं. 3 संभवः. 4 अवसरः, अवकाशः. -*v. i.* दैवात् अकस्मात् आपत् 1 P or समापद् 4 A or उपस्था 1 U or वृत् 1 A; oft. ex. by यदृच्छया, दैवात्, with verbs; 'c. ed to see two Kinnaras' किन्नरमिथुनं यदृच्छयाद्राक्षीत् (Ka 119); 'I c. ed to see her' सा दैवान्मम लोचनपथं याता; 'whom I c. ed to see' समापतितदृष्टः; 'stand a good c.' उपपत्तिं अपेक्ष् 1 A.

Chancellor, *s.* प्रधानधर्माधिकारिन् *m.*, अध्यक्षः.

Chandelier, *s.* दीपवृक्षः, दीपाधारः.

Chandler, *s.* वार्तावहः, वि(वै)वधिकः.

Change, *s.* परि(री)वर्तः, परिवर्तनं, परिवृत्ति *f.*, विपर्ययः, (ग्रहण-विपर्ययः); विकारः, विकृति *f.*, विक्रिया (of feelings &c); 'oh, what a c. in the site of the ground!' अहो अनवस्थितो भूसंनिवेशः (U. 2); विपरिणामः विपरीतः विवर्तः. 2 अल्पार्घमुद्रा. 3 श्रेष्ठिचत्वरं. 4 विभेदः, वैचित्र्यं. 5 निवर्तनं. -*v. i.* परिवृत् 1 A; 'in this c. ing world' परिवर्तिनि संसारे; अन्यथा अन्यरूप *a.* भू अंतर affixed to nouns; 'the colour of the water c. ed in a moment' जले क्षणेनैव वर्णांतरमुपागमत्, विपर्यासं या 2 P, विपर्यस् 4 P, विकृ pass. or विकारं या. -*v. t.* परिवृत् c., विकृ 8 U; 'nature can't be c. ed' स्वभावो दुरतिक्रमः; विपर्यस् c., अन्यथाकृ; oft. ex. by (*s.*) with कृ, or अन्य-भिन्न *a.* कृ. 2 विनि-वि-मे 1 A, प्रतिदा 1 P, 3 U. 'to be c. ed into' ex. by भावेन परिणम् 1 U, भावमापद् 4 A: 'milk is c. ed into curds' क्षीरं दधिभावेन परिणमते (S. B. 475); न हि वायुर्दधिभावमापद्यते (S. B. 476); 'he has c. ed his evil course of life' पापाचरणान्निवृत्तोऽसौ; 'c. ing his clothes' वेषपरिवर्तनं विधाय. 'c. colour' *v. i.* रक्तीभू; विवर्ण *a.* भू 1 P. **-able, -ful,** *a.* लोल, चपल अधीर, अस्थिर; नकभावाश्रय, अनित्य, चल, अस्थायिन्. **-ling,** *s.* कृत्रिमपुत्रः पुत्रप्रतिनिधिः.

Channel, *s.* स्रोतस् *n.* ... प्रणाली, कुल्या, खातं. 2 नदीपात्रं-गर्भः. 4 संकटः; संकट-संकीर्णपथः. -*v. t.* खन् 1 P, कुल्याः कृ 8 U.

Chant, *v. t.* गै 1 P, पठ् 1 P. -*s.* गीतं गानं स्तोत्रं **-er,** *s.* गातृ *m.*, गायकः.

Chanticleer, *s.* कृकवाकुः, उषाकलः, ताम्रचूडः.

Chaos, *s.* संकरः, संकुलं, संकीर्णता, अव्यवस्था. **-Chaotic,** *a.* संकीर्ण, संकुल, अस्तव्यस्त.

Chap, *s.* बटुः, माणवकः. 2 गर्तः, छिद्रं, रन्ध्रं; 'c. s' आस्यं, वदनं. -*v. i.* (शीतवशात्) विभिद् pass., स्फुट् 4, 6 P, विदॄ pass., स्फुट 6 P.

Chape, *s.* बंधनी, ग्रंथनी.

Chapel, *s.* देवायतनं, देवालय.

Chaperon, *s.* (जनसमाजे) नारीसहचरः.

Chaplain, *s.* पुरोहितः; कुलगुरुः कुलाचार्यः.

Chaplet, *s.* *See* **Garland.**

Chapman, *s.* *See* **Pedlar.**

Chapter, *s.* अध्यायः; परिच्छेदः, स्कंधः, उल्लासः, उच्छ्वासः, प्रकरणं (of various compositions).

Char, *v. t.* अंगारीकृ 8 U, ईषद् दह् 1 P. 2 Do. q. v. -*s.* *See* 'Chare.'

Character, *s.* अक्षरं वर्णः 2 निसर्गः, प्रकृति *f.*, स्वभावः. 3 शीलं, चारित्र्यं सौजन्यं. 4 कीर्ति *f.*, यशस् *n.*, गौरवं; 'he obtained the c. of a dull boy' मंदमतिरसाविति स विख्यातो बभूव. 5 रूपं, लक्षणं, चिह्नं, अभिज्ञानं; 'assuming the c. of an astrologer' कार्तांतिको नाम भूत्वा. 6 गुणः, विशेषः. 7 भूमिका; 'chief c.' प्रधानपुरुषः, नायकः. **-istic,** *s.* स्वभावः, लक्षणं, चिह्नं विशेषः, विशेषणं, विशिष्टलिंगं. -*a.* स्वभावानुरूप, स्वाभाविक (की *f.*). **-ize,** *v. t.* विशिष् c., संलक्ष् 10; विशेषणं दा 3 U. 2 गुणदोषविवेचनं कृ 8 U. **-less,** *a.* विशिष्टगुणरहित.

Charade, *s.* सर्वतोभद्रः.

Charcoal, *s.* अंगारः-रं, दग्धकाष्ठं.

Chare, *s.* नियुक्त *a.* कर्मन् *n.*

Charge, *v. t.* अवस्कंद् 1 P, अभिद्रु 1 P. *See* **Attack.** 2 **Accuse,** q. v. 3 आदिश् 6 P,

आज्ञा 2 P, आज्ञा c. (आज्ञापयति). 4 मूल्यं धार्य 10 A; 'you will be c. ed 8 Rupees' अष्टरूपकं त्वया देयं भविष्यति. 5 निक्षिप् 6 P, सम्-अर्प् c. (अर्पयति), न्यस् 4 P ; नियुज् 7 A, 10 ; योग्यसचिवे न्यस्तः समस्तो भरः (Rat 1) 'a competent minister is c. ed with the whole responsibility.' 6 भार न्यस् or निविश् c.; 'c. ed with water.' जलपूर्णः- गर्भः (मेघः). -s. निक्षेपः, न्यासः; 'give in c. of.' हस्ते निक्षिप्; सम्-अर्प् c. ; अयं जनः कस्य हस्ते समर्पितः, एषा हस्ते वो निक्षेपः (S. 4): इमां देवीहस्ते निक्षिपता (Rat. 1). 2 रक्षणं, अवेक्षा, गुप्ति f. 3 आदेशः, आज्ञा, शासनं 4 नियोगः, अधिकारः. 5 अभियोगः, मिथ्याक्रोषः, दोषारोपः; 'lays a crime to one's c.' कस्मिन्नपि दोषमारोपयति. 6 अवस्कंदः, आक्रमः. संघट्टः, अभिसंपातः. 7 भारः. 8 व्ययः. 9 मूल्यं, अर्घः. -er, s. युद्धाश्वः, वाजीरः. 2 पात्रं, भाजनं.

Chariot, s. रथः, स्यंदनः. **-eer,** s. सारथिः, सूतः, सव्येष्ठ m., नि-,-यंतृ m.

Charity, s. भूतानुकंपा, दीनवत्सलता, दयालुत्वं, कृपा. 2 दानं, भिक्षादानं, त्यागः ; 'out of c.' पुण्यार्थं. **-able,** a. दीनवत्सल, दानशील, धर्मात्मन्, दरिद्रपालक. 2 सदय, कृपालु, दयार्द्र, अनुकंपारत. 3 अनसूयक, परदोषसहन. **-ably,** adv. सदयं, सानुकंपं; अनसूयया, अमत्सरं.

Chark, v. t. See **Char,** v. t. s. अंगारः.

Charlatan, s. छद्मवेषः, मिथ्याचिकित्सकः. 2 छद्मिन् m., मायिन्-कपटिन् m., छाद्मिकः. **-ical,** a. दांभिक-छाद्मिक (की f.). **-ry,** s. मिथ्याचिकित्सा; छलं, छद्मन् n., माया, वंचनं.

Charm, s. मारकं, मंत्रः. 2 रक्षाकरंडः. 3 मनोरमत्वं, चित्ताकर्षकत्वं, रामणीयकं, मनोज्ञता, शोभा. कांति f., श्रीः. 3 प्र-वि-लोभनं. -v. t. मंत्रैर्वशीकृ 8 U, अभिचर् c. 2 परि-वि-मुह् c., हृ 1 P.' I was c. ed by the melody of thy song ' तव गीतरागेण हृतोस्मि (S.1). **-er,** s गारुडिकः, जांगुलिकः. 2 मायिन् m., मोहिन् m., कुहककारः. 3 प्रिया, मुग्धा (of women) **-ing,** a. रमणीय, रम्य, मनोरम, सुभग, कमनीय, चेतोहर, कांत, हारिन्. **-ingly,** adv. मनोरमं, सुभगं, चारुतया. **-less,** a. निःश्रीक, कांतिहीन.

Chart, s. वेलापटः.

Charter, s शासनपत्रं.

Char-woman, s. दिनिकाचेटी, सरं(रिं)ध्री.

Chary, a. परिमित, सावधान, अमुक्तहस्त. **-ly,** adv. अमुक्तहस्तं

Chase, v. t. अनुधाव्-अनुसृ-अनुगम् 1 P, मृग् 10 A. 2 (away) निरस् 4 P, अपानुद् 6P, विधू 5, 9 U, निराकृ 8 U, विद्रु c. -s. मृगया, आखेटः. 2 अनुसरणं, अनुधावनं, 'gave c.' अन्वसरत. 3 जांगलं. **-er,** s. अनुधावकः, मृगयुः; 'beast of c.' मृगः 'wild goose c.' निरर्थकव्यापारेषु अभिनिवेशः, मौर्ख्यं.

Chasm, s. रंध्रं, बिलं, विवरं, दरी, गर्तः.

Chaste, a. (Of a woman) सती, कुलवधूः, कुलस्त्री, अपांसुला, पतिव्रता, विशुद्धशीला. एकपत्नी. 2 विशुद्ध, निर्मल. 3 जितेंद्रिय, निष्काम, अव्यभिचारिन् **-Chastity,** s. सतीत्वं, चारित्र्यं, पातिव्रत्यं. 2 विशुद्धि f., शुचिता. 3 इंद्रियनिग्रहः, ब्रह्मचर्यं, जितेंद्रियत्वं.

Chastise, Chasten, v. t. दंड् 10, अनुशास् 2 P. **-er,** s. दंडप्रणेतृ m., शास्तृ m. **-ment,** s. शासनं, निग्रहः, दंडः.

Chat, v. i. विश्रब्धं आलप् 1 P or संभाष् 1 A or संलप्; वृथाकथां कृ 8 U. -s. संलापः, संकथा, संभाषणं, विश्रंभालापः, वृथाकथा

Chateau, s. कोटः.

Chattels, s. अस्थावरद्रव्यं, विभवः.

Chatter, s. किलकिलारावः. 2 विप्रलापः, अल्पितं, वृथालापः, प्रजल्पः. -v. i. प्रजल्प्-प्रलप् 1 P. 2 किलकिलरवं कृ 8 U, कूज् 1 P; 'with c. ing teeth' दंतैर्दंताभिघ्नन्, दंतवीणां वादयन्. **-er,** s. जल्पकः, वाचालः, वावदूकः.

Chaw, v. t. चर्व् 1. P, परि-सं-दंश् 1 P. **-bacon,** s. असभ्यः, ग्राम्यो जनः.

Cheap, a. अल्पमूल्य, अल्पार्घ सुलभ, सुखक्रेय. **-en,** v. t. मूल्यं-अर्घं-न्यूनीकृ 8 U or अल्पीकृ; अर्घतः पत् c. **-ly,** adv. अल्पमूल्येन, अल्पार्घेण, सुलभं.

Cheat, v. t. वंच् 10, प्रलुभ् c., विप्रलभ् 1 A, अति-अभि-संधा 3 U; छल् 10, शठ् 10, मुह् c. -s. वंचनं,कपटं.प्रतारणं, कैतवं माया, भ्रमः, मोहः. 2 वंचकः, धूर्तः, प्रतारकः, कितवः, कपटिन् m. **-ing,** s. प्रतारणं. अतिसंधानं, वंचनं, &c.

Check, v. t. नि-सं यम् 1 P, प्रतिबंध् 9 P प्रतिहन् 2 P, वार् 10; निग्रह् 9 P, निरुध् 7 U, नि-प्रति-षिध् 1 P, विष्टंभ् 9 P.-s. प्रतिबंधः, प्रत्यूहः; संरोधः, प्रतिषेधः,निग्रहः,संयमः, निवारणं, निरोधः.

Checkmate, v. t. पराभू 1 P; भंज् 7 P; s. पराभवः, भंगः.

Cheek, s. कपोलः, गंडः, गल्लः करटः (of elephants); 'broad c. s' गंडभित्ती; मांसलकपोलौ; ' c. bone ' कपोलफलकः. **-y,** a. उद्धत, धृष्ट.

Cheep, v. i. चिक् 2 P. कूज् 1P.

Cheer, s. हर्ष-(द्योतक) निस्वनः, जयध्वनिः-शब्दः. 2 स्थैर्यं, धैर्यं, स्थिरता; 'be of good c.' or 'c. up' समाश्वसिहि, धैर्यं निधेहि हृदये. 3 आहारः, भोजनं. -v. t. आ-

समा-श्वस् c. सांत्व् 10 2 प्रहृष् c., मुदा उल्लस् c., आनंद् c. 3 प्रोत्सह् c., मेद् c. 4 प्रसद् c., स्थिरीकृ 8 U (भवतीभ्यामेव स्थिरीकर्तव्या शकुंतला S. 4). -v. i. (up) आ-समा-श्वस् 2 P; हृष् 4 P. -ful, a. सहर्ष, प्रफुल्ल, सानंद, हृष्ट, प्रसन्न, आनंदित, उल्लासित. -fulness, s. प्रसन्नता, प्रसादः, उल्लासः, हर्षः, आनंदः, आह्लादः, प्रमोदः. -less, a. विषण्ण, निरानंद.

Cheese, s. किलाटः, दधिजं, मथजं; 'c. curds' कूर्चि n., क्षीरजं. -monger, s. दधिजविक्रयिन् m.; 'c.paring,' a. कृपण, कदर्य, -s. कृपणता.

Chemise, s, कंचुकः, चोलः.

Chemistry, s. रसक्रिया, रसतंत्रं-विद्या.-Chemist, s. रसज्ञः, रसतंत्रविद् m. -Chemical works, रसक्रियागारं-शाला.

Cheque, s. धनप्रदानलेखः.

Chequer, v. t. चित्र् 10, कर्बुरीकृ 8 U, शबलीकृ. -ed, a. कर्बुरित, शबल, कल्माष, चित्र.

Cherish, v. t. लल् 10, पुष् 1, 4, 9 P, पा c. (पालयति), संवृध् c., भृ 3 U. 2 धृ 10, बंध् 9 P; 'c. ed hatred towards him' तस्मिन् द्वेषं बबंध. 3 भज् 1 U, उपास् 2 A, निविश् c.; ध्यै 1 P; 'c. ing Hari in his heart' हरिं मनसा ध्यायन्. 4 Love, q. v.; 'c. those (hearts) that hate thee' भज द्विषोऽप्यनुनय (Bh.I.77).-er, s. पोषकः, संवर्धकः, पालकः.

Cheroot, s. See **Cigar.**

Chersonese, s. द्वीपकल्पः-ल्पं.

Cherub, s. स्वर्ग-दिव्य-दूतः. -ic, a. दिव्य.

Chess, s. चतुरंगं; 'c. board' अष्टापदं, शारिफलं; 'c. man' शारः, शारिः.

Chest, s. See **Breast,** and **Box,** s.

Chevalier, s. सादिन् m., अश्वारोहः, महावीरः.

Chew, v. t. चर्व् 1 P, संदंश् 1 P; 'c. the cud' रोमंथं अभ्यस् 4 P, रोमंथायते (D.). -ing, s. रोमंथः, चर्वणं.

Chicane, s. कपटं, छलं, व्यपदेशः, मिथ्यापत्ति f. -er, s. मिथ्याविवादिन् m. -ery, s. वाक्छलं, मिथ्यावादः, पक्षाभासः, अनृतवाद् f.

Chicken, s. कुक्कुटशावः; 'c. hearted' भीरु, कातर.

Chick-peas, s. चणकः,

Chide, v. t. निर्भर्त्स् 10 A, तर्ज् 10A, निष्ठुरमभिधा 3 U. 2 निंद् 1 P; अधिक्षिप् 6 P; See **Censure.** -v. i. उत्क्रुश् 1 P; विवद् 1 A, विप्रवद् 1 U, कलहं कृ 8 U. -er, s. निंदकः.

Chief, a. प्रधान, अग्रिम, मुख्य, परम, उत्तम, प्रमुख, अग्र्य, विशिष्ट; वर-पुंगव-इंद्र-ऋषभ- in comp. -s. प्रधानपुरुषः, अधिपतिः, नायकः, ईशः, अग्रिमः, ईश्वरः, पुरोगः, अध्यक्षः, अधिष्ठातृ m., मुख्यः; 'military c.' सेनापतिः, सेनाध्यक्षः, चमूपतिः. -ly, adv. प्रधानतः, विशेषेण-तः, मुख्यशः-तः. -tain, s. मुख्यः, नायकः, पतिः, ईश्वरः. 2 गणपतिः, सामंतः.

Chilblain, s पादस्फोटः, क्षतं.

Child, s. बालः-लकः, शिशुः, अर्भकः, दारकः, अपत्यं, सूनुः, पुत्रः; वत्सः त्सा, जातः-ता, (terms of endearment). 2 संतानः, प्रजा, संततिf., अपत्यं, प्रसूति f.; 'to be with c.' See **Pregnant;** 'c. bearing' प्रसवः; beyond c. bearing' विगतार्तवा, निष्फला; 'capable of c.' सरजस्का; 'c. bed' प्रसवावस्था, प्रसूतिकालः; 'c. birth' प्रसवः, जननं. -hood, s. बाल्यं, शैशवं, कौमारं-रकं, बालभावः, बालावस्था. -ish, a. बालिश, बालेय, बालोचित, बाल in comp. -ishly, adv. बाल-शिशु-वत्, शिशुवत्. -less, a. निरपत्य, असंतान, अपुत्र, निरन्वय, निर्वंश, पुत्ररहित, अप्रजस् and sim. comp.; 'a c. woman' वंध्या, अशिश्वी. -like, a. शिशुतुल्य, बालानुरूप, बालोपम; 'c. wife' शैशवे भार्यापदं प्राप्ता (बालिका); 'c's play' (क्रीडावत्) सुकर a. कर्मन् n. 'from (of) a c.' आशैशवात्, बाल्यात्प्रभृति; 'second childhood,' वार्धक्ये बालिशता.

Chill, a. शीतल, शित, शिशिर. -s. शैत्यं, शीतं, हिमं. 2 स्वेदविष्टंभः. -v. t. शीतीकृ 8 U, तेजोहीन a. कृ, उत्साहं ध्वंस् c. -y, a. ईषच्छीत, आशिशिर. 'To take the c. of' कदुष्णं कृ 8 U.

Chime, v. i. संवद् 1 P, अनुगुण-अनुरूप-a. भू 1 P; 'c. in with', संवद् 1 P. -v. t. वद् c., वादित्राणि तड् 10. -s. एकतानः, सालेकर्ष, स्वरसंवादः. 2 घंटानादः.

Chimera, s. असंभवकल्पना, मनोरथसृष्टि f., शशविषाणं; वृथा-मिथ्या-वासना. -Chimerical, a. मनोरथसृष्ट, काल्पनिक (की f.), भावनाकल्पित, अमूलक.

Chimney, s. धूमनिर्गमः, धूमनाली-रंध्रं. 2 चुल्लि-ल्ली f., अग्निकुंडं; 'c. piece' चुल्लि-शीर्षशिला; 'c. sweeper,' धूमनालीसंमार्जकः.

Chin, s. चिबुकं, हनु m., f. 'Up to the c.' आकंठं (मग्न a.).

China, China-ware, कौलालकं, मृन्मय a. भांडं.

China-cloth, s. चीनांशुकं.

Chine, s. पृष्ठं, कशेरुका. 2 कंधरः, श्रोणी.

Chink, s. छिद्रं, रंध्रं. 2 क्वणितं, रावः. -v. i. स्फुट् 6 P, भिद् pass. 2 शिंज् 1, 2 A; क्वण् 1 P, स्वन् 1 P. 3 छिद्रं पूर् 10. -y, a. अनेकरंध्र, बहुविवर.

Chip, *s.* खंडः-डं, शकलः-लं, लवः, विदलं, दलं. —*v. t.* तक्ष् 1, 5 P; खंडीकृ 8 U. 2 *See* **Bet.** 'C. axe' तक्षणी. —**Chippings,** *s.* तक्षाणि, खंडानि. —**py,** *a.* अस्वस्थ, असुस्थ. 2 स्वंतपूर्ण. 'C. of the old block,' पितृसदृशः.

Chirk, (I) (*m*), *v. i. See* **Chirp.**

Chirognomy, *s.* सामुद्रिकं.

Chirography, **-er,** *See* **Writing, Writer.**

Chiromancer, *s.* हस्तरेखाविद्याज्ञः, सामुद्रिकः.

Chiropodist, *s.* करचरणवैद्यः.

Chirp, *v. i.* विरु 2 P, कूज् 1 P. 2 सानंदं वद्, 1 P. **-ing,** *s.* विरावः, कूजितं, रुतं. **-ing, -er-y,** *a.* उल्लसित, प्रहृष्ट, प्रफुल्लवदन.

Chirrup, *See* **Chirp.**

Chirt, *v. t.* नि-पीड् 10.

Chisel, *s.* प्रश्चनः, तक्षणी, टंकः. —*v. t.* व्रश्च् 6 P, तक्ष् 1, 5 P.

Chit, *s. See* **Boy.** 2 पत्रं. **-chat,** *s.* जल्पनं, विश्रंभालापः, विश्रंभकथा.

Chivalry, *s.* शौर्यगुणः, सुविक्रमः, सुवीर्यं, शौर्यं, धामन् *n.* **-ous,** *a.* धामवत्, सुविक्रांत, महावीर्य.

Choice, *s. See* under **Choose.** 'To make a. c. or take one's c.,' वृ 5 U. 10; वृ 9 U; अभीष्टं ग्रह् 9 U.

Choir, *s.* गायक संघातः-गणः, गायकवर्गः.

Choke, *v. t.* प्रति-नि-रुध् 7 U, स्तंभ् 9 P. 2 कंठं संपीड् 10, गले ग्रह् 9 P, श्वासावरोधं कृ 8 U, श्वासं निरुध्. **-ed,** *a.* कलुष, (कंठः स्तंभितबाष्पवृत्तिकलुषः S. 4); निरुद्धश्वास.

Choler, *s.* पित्तं. 2 क्रोधः, अमर्षः; *See* **Anger.** **-ic,** *a.* क्रोधिल, क्रोधन, चंड, कोपिन्; 'c. constitution' पित्तप्रकृतिः, कोपशीलता.

Cholera, *s.* विषू(सू)चिका, महामारी.

Choose, *v. t.* वृ 5 U, वृ 9 U. ग्रह् 9 P. (the sense being clear). 2 अभिलष् 1, 4 P, मनो बंध् 9 P; रुच् 1 A, इष् 6 P. 3 निश्चि 10, नियुज् 7 A, 10. —**Choice,** *s.* वरणं, वरः, ग्रहणं; अभिलाषः, मनोबंधः; 'c. of a husband' स्वयंवरः; 'of one's c.' यथेप्सितं, यथाकामं, यथेष्टं, स्वेच्छया. 2 उत्तमभागः, उत्तमांशः. 3 विकल्पः; कामः, रुचि *f.*; 'you have no c. in this matter' स्वेच्छया वर्तितुं न शक्नोषि. —*a.* सर्वोत्तम, विशिष्ट, उत्कृष्ट, परम, सार-विशेष-रत्न in comp.; 'c. food,' भोजनविशेषः, विशिष्टान्नं; 'c. girl' स्त्रीरत्नं. **-less,** अविकल्प.

Chop, *v. t.* खंडशः छिद् 7 P, कृत् 6 P, शकलीकृ 8 U; *See* **Cut.** —*s.* खंडः-डं, शकलः-लं; 'c. house' पाकशाला. —**Chops,** *s.* आस्यं वदनं.

Chord, *s.* गुणः, तंत्री. 2 ज्या, जीवा.

Chorion, *s.* गर्भकोशः, गर्भवेष्टनं.

Chorister, *s.* गायकः, चारणः, किन्नरः.

Chorus, *s.* ध्रुवः-वकः, अनुपदं. 2 गायकगणः

Chouse, *v. t. See* **Cheat.**

Chowrie, *s.* चामरं, रोमगुच्छः.

Christen, *v. t.* नाम कृ 8 U or धा 3 U. *See* **Call.**

Chromatic, *a.* वर्णसंबंधिन्. 2 ग्रामीय.

Chronic, *a.* कालिक (की *f.*), दीर्घस्थायिन्, अविसर्गिन्.

Chronicle, *s.* इतिहासः, पुरावृत्ताख्यानं, वृत्तविवरणं. —*v. t.* अभिलिख् 6 P, वृत्तांतं लिख्; यथाक्रमं रच् 10. **-er,** *s.* पुरावृत्तरचकः, इतिहासलेखकः.

Chronology, *s.* कालनिर्णयविद्या. 2 कालक्रमेण पुरावृत्तविवरणं. **-ist,** *s.* कालगणकाज्ञः, पुरावृत्तरचकः. **-ical,** *a.* कालानुसारिन्, कालक्रमानुसारिन्; 'in c. order' आनुपूर्व्येण, अनुपूर्वशः; कालानुसारेण.

Chronometer, *s.* कालमापनं, घटी, घटिकायंत्रं.

Chrysalis, *s.* कोषकारः, कोशस्थः.

Chrysolite, *s.* चंद्रकांतः.

Chrysophilite, *s.* सुवर्णप्रियः, कनकलुब्धः.

Chub-faced, *a.* स्थूलास्य.

Chuck, *s.* कुक्कुटीशावः. **-ling,** प्रिये, वत्से, वत्सजात (voc.). 2 चपेटिका, ईषत्प्रहारः, लघ्वाघातः.

Chuckle, *v. i.* अंतः विहस् 1 P or स्मि 1 A, आनंदं भज् 1 U. —*a.* अबुद्ध, ग्राम्य. 'C. head,' ग्राम्यो जनः.

Chuff, *s.* ग्रामिकः, स्थूल-जड-बुद्धिः, असभ्यः **-y,** *a.* ग्राम्य, स्थूल, असभ्य.

Chum, *s.* वयस्यः; मित्रसुहृद् *m.*

Chump, *a.* जडबुद्धि, स्थूलधी.

Church, *s.* देवतायतनं, देवालयं, धर्ममंदिरं, भजनगृहं. 2 धर्मः **-y,** *a.* धर्मोन्मत्त, अतिभक्त्याग्रह 'C. yard,' श्मशानं, पितृवनं, प्रेतभूमि *f.*

Churl, *s.* ग्राम्यजनः, ग्रामजः, वृषलः. 2 अविनीतः, असभ्यः; वामशीलः. 3 कृपणः, कदर्यः. **-ish,** *a.* अशिष्ट, अश्लील, ग्राम्य, अविनीत, असभ्य. 2 खल, कदर्य, दुराचार. **-ness,** *s.* अविनयः, असभ्यता, &c.

Churn, *v. t.* मथ् 1 P, मंथ् 9 P, (with two acc.); 'the ocean was c. ed for nectar' अमृतमंबुनिधिर्ममंथे; समा-आ-लुड् 1 P, or c. **-ing,** *s.* मंथनं, मंथः; 'c. stick, -handle' मंथनदंडः, मथिन् *m.*, मंथानः 'c. rope' मंथनरज्जु *f.* 'C. ing stick' मंथः, मंथदंडः, वैशाखः; 'a pot used for ing,' गर्गरी, मंथनी.

Chute, *s.* जलप्रपातः.
Chutni, *s.* उपदंशः, व्यंजनं.
Chyle, *s.* अन्नरसः, धातुपः. **-ous,** *a.* अन्नरसमय (यी *f.*).
Cicatrice, Cicatrix, *s.* किणमन् *n.*, रूढक्षतं. **-Cicatrize,** *v. t.* क्षतं रुह् c. or शुष् c. ; 'c. ed' रूढ, शुष्क, रोपित. **-ation,** *s.* व्रणरोपणं, व्रणशोषणं.
Cicerone, *s.* अपूर्ववस्तुदर्शकः.
Cidevaunt, *a.* पूर्व.
Cigar, Cigarette, *s.* तमाखुनाली.
Cimex, *s.* मत्कुणः, रक्तपः.
Cinch, *s.* पर्या(ल्या)णबंधः.
Cincture, *s.* मेखला, रशना, कांची
Cinder, *s.* अंगारः-रं, भस्मन् *n.*, अग्न्युच्छिष्टं.
Cinerary, *a.* भस्मसंबंधिन्.
Cinnabar, *s.* रक्तपारदः.
Cinnamon, *s.* दारुगंधः, दारुसिता, सुगंधित्वच् *f.*
Cinque, *s.* पंचकं, पंचन् in comp.
Cipher, *s.* शून्यं, बिंदुः, खं. 2 अक्षरं, वर्णः. 3 बीजाक्षरं ; गूढाक्षरं. 4 अंकः. *-v. t.* अंकविद्यां अभ्यस् 4 P or शिक्ष् 1 A. 2 गूढाक्षरैर्लिख् 6 P. **-ing,** *s.* अंकविद्या, गणनविद्या, गणितं.

Circle, *s.* मंडलं, वृत्तं, चक्रं, वलयः-यं, गोलः-लं; 'c. of friends' मित्रचक्रं-मंडलं; 'c. of people' परिषद् *f.*; 'being in the c. of her friends' सखीमध्यगता; तापसपरिषच्चक्रमंडला प्रतिभाते (Ka. 49) 'formed into, or sitting in, a c.' &c. 2 परिधिः, परिणाहः; 'area of a c.' फलं; 'segment of a c.' वृत्तखंडं. *-v. t.* परिवृ 5 U, परिवेष्ट् 1 A or c., परि-इ 2 P. *-v. i.* चक्रवत्-मंडलाकारेण-परिवृत् 1 A or परिभ्रम् 1, 4 P. **-Circular,** *a.* वर्तुल, वृत्त, मंडलाकार, चक्राकृति, गोल. **-ly,** *adv.* चक्रवत्, मंडलरूपेण.
Circuit, *s.* परिभ्रमणं, पर्यटनं; आ-नि-वि-वर्तः, आवृत्ति *f.* 2 मंडलं, परिधिः, परिणाहः. *-v. i.* (to make a c.) परिभ्रम् 1, 4 P, परि-इ 2 P, परिवृत् 1 A. **-ous,** *a.* वक्र, कुटिलगामिन्, अतिदीर्घ.
Circulate, *v. t.* प्रचल् c., प्रसृ c., परिवृत् c., प्रवृत् c. ; 'who c. ed false reports all around' समंतात् प्रवृत्तबीभत्सकिंवदंतीकाः (पौरजानपदाः) (U. 4). *-v. i.* आ-वि-परि-वृत् 1 A, प्रचर्-चल्-1 P, प्रसृ 1 P. **-ion,** *s.* परिभ्रमणं, परिवर्तनं, प्रसरः, प्रचारः, चलनं, व्यावर्तः; 'c. of blood' रुधिराभिसरणं, रक्तवहनं. **-ing,** *a.* परिवर्तिन्, व्यावर्तक.
Circumambient, *a.* परिगत, व्यापक, परिवेष्टक.

Circumambulate, *v. t.* परि-इ 2 P, परिभ्रम् 1, 4 P, परिक्रम् 1 P, प्रदक्षिणीकृ 8 U. **-ion,** *s.* परिभ्रमणं, पर्यटनं, प्रदक्षिणा.
Circumcise, *v. t.* त्वचं छिद् 7 P or कृत् 6 P; 'c. ed man' मुंडः-डः, दुश्चर्मन् *m.*
Circumduct, *v. t.* लुप् 6 P; *See* **Baffle.** *-v. t.* परिवृत् c. **-ion,** *s.* लोपः; मोघीकरणं.
Circumference, *s.* परिधिः, मंडलं, परिवेशः-षः, परि(री)णाहः; 'c. of a wheel' नेमि *f.*, प्रधिः, नीध्रः.
Circumfluent, -fluous, *a.* परिस्यंदिन्, परिगत, परिगलित. **-Circumfluence,** *s.* परिस्रवः, परिस्यंदनं.
Circumfuse, *v. t.* परि-समा-कृ c., समाक्रम् 1 U, 4 P, व्याप् 5 P, वि-अश् 5 A. **-ile,** *a.* व्यापक.
Circumjacent, *a.* उपांतिक, पर्यंतस्थ.
Circumlocution, *s.* वक्रोक्ति *f.*, वाक्यविस्तरः; अत्युक्ति *f.*, अतिशयोक्ति *f.* **-Circumlocutory,** *a.* वक्र, बहुवाक्य, सवाक्यविस्तर.
Circumnavigate, *v. t.* पोतेन परिभ्रम् 1, 4 P, समंततः प्लु 1 A, द्रु 1 P
Circumrotation, *s.* चक्रावर्तः, परिवर्तः, आवृत्ति *f.* **-Circumrotatory,** *a.* आवर्तमान, परिवर्तिन्.
Circumscribe, *v. t.* परिमा 3 A, सं-नि-यम् 1 P, संवृ 5 U, संकुच् c. **-Circumscription,** *s.* संकोचः, संयमः.
Circumspect, *a.* समीक्ष्यकारिन्, विमृश्यकारिन्, सावधान, अवहित, अप्रमत्त, दक्ष. **-ion,** *s.* समीक्ष्य-विमृश्य-कारित्वं, अप्रमादः, अवधानं, दक्षता. **-ly,** *adv.* समीक्ष्य, सुविमृश्य, सावधानं.
Circumstance, *s.* दशा, अवस्था, स्थिति *f.*, भावः, वृत्ति *f.* 2 वृत्तं, वृत्तांतः; 'c. s as they happened' यथावृत्तः वृत्तांतः. 3 विषयः, वस्तु *n.*, अर्थः. 4 संबंधः; 'under these c. s' एवंगते-सति; 'in good c. s' सुस्थ-सुस्थित-*a.*; 'in bad c. s' दुर्गत-दुर्दशापन्न-दुःस्थित *a.* ; 'under any c. s' यद्वा तद्वा भवतु; येन केनापि प्रकारेण, according to c. s' यथास्थितं, यथासंभवं, यथावसरं, यथाकालं. **-ed,** *a.* स्थित, अवस्थित, भूत, स्थ in comp. **-Circumstantial,** *a.* सविस्तर, विस्तीर्ण. 2 अप्रकृत, आगंतुक (की *f.*), आहार्य; अप्रत्यक्ष (प्रमाणं). **-ly,** *adv.* यथावृत्तं, सविस्तरं, &c. **-Circumstantiate,** *v. t.* अप्रत्यक्षप्रमाणेन प्रतिष्ठा c.
Circumvallate, *v. t.* परिखाभिः परिवेष्ट् 1 A, or उपरुध् 7 U. **-ion,** *s.* समंतादुपरोधनं, परिखानिर्माणं.
Circumvent, *See* **Cheat.**
Circumvent, *v. t.* परिणी 1 P, परिधा 3 U.

Circumvolve, *v. t.* See **Revolve.**
Circus, *s.* क्रीडारंगः, क्रीडांगणं, क्रीडाचक्रं.
Cist, *s.* कोशः, पुटः, आवरणं. 2 समाधि *m.* 3 समाधिगतं-कोशः-पुटः
Cistern, *s.* जलकुंडं, जलाशयः, तोयाधारः.
Cit, *s.* नागरिकः, पुरजनः, नागरजनः.
Citadel, *s.* दुर्गं, कोटः-टि *f.*
Cite, *v. t.* उपन्यस् 1 P, उपन्यस् 4 P, उपक्षिप् 6 P, अवतृ *c.* 2 आह्वे 1 P, अभियुज् 7 A, 10. **-ation,** *s.* आह्वानं, अभियोगः. 2 अवतारणं, उपन्यस्तवाक्यं, अवतरणं.
Citron, *s.* जंबीरः, जंभीरः, जंभः-भलः, बीजपूरः, फलपूरः.
City, *s.* पुरं-री, नगरं-री, पत्तनं, पुर् *f.* **-Citizen,** *s.* पौरः, पुरवासिन् *m.*, नगरजनः, पौरजनः, पत्तनलोकः; 'c. s and villagers' पौरजानपदाः. **-like,** *adv.* आर्यवत्, नागरिकवृत्त्या, पौरवत्. **-ship,** *s.* पौरत्वं, पौराधिकारः.
Civet,-Cat, *s.* गंधमार्जारः.
Civil, *s.* पौर (री *f.*).
Civil, *a.* दक्षिण, सादर, विनयवत्, सानुनय; अनुकूल; सुशील. 2 पौर (री *f.*), पुर in comp.; 'c. war' प्रकृतिक्षोभः, जनपदकोपः. **-ity,** *s.* दाक्षिण्यं, प्रश्रयः, आदरः, सौजन्यं, अनुरोधः, अनुवृत्ति *f.*, सुशीलता. **-ly,** *adv.* सादरं, सप्रश्रयं. **-Civilize,** *v. t.* विनी 1 P, शिष्टाचारान् शिक्ष् *c.* or शास् 2 P, आर्यपदवीं आरुह् *c.* (रोपयति), उन्नम् *c.* (नमयति), उत्कर्षं-उन्नतिं-नी. **-ation,** *s.* सभ्यता, आचारशिष्टता. **-ed,** *a.* शिष्टाचारपर, आर्यवृत्त, शिष्ट, सभ्य, विनीत.
Clack, *s.* वाचालता, अतिजल्पनं. 2 किलकिलारावः. 3 चकचकध्वनि *m.* **-v.** *i.* अतिधृष्टं जल्प् 1 P. 2 किलकिलारावं कृ 8 U. 3 चकचं स्वन् 1 P.
Clad, See under **Clothe.**
Claim, *v. t.* स्वीय-आत्मीय-त्व इति प्रतिपद् *c.* or याच् 1 A or ब्रू 2 U or वद् 2 P; 'he c. s that property' मदीयमिति स आह or प्रतिपादयति; 'c. s reverence' संमाननमर्हतीति प्रतिपादयति; ममेति उक्त्वा ग्रह् 9 P; अभिमानं कृ 8 U, स्वत्वं ज्ञा *c.* (ज्ञापयति), अभिमन् 4 A. 2 (have a c. to) अर्ह् P. **-s.** अधिकारः, अभियोगः, अभिमानः, स्वत्वप्रतिपादनं, याचना; 'false c.' मिथ्याभियोगः; 'laying c. to learning' विद्याभिमानः. **-ant,** *s.* अर्थिन् *m.*, अभियोक्तृ *m.* प्रार्थयितृ *m.*
Clam, *v. t.* सांद्रीकृ 8 U, श्यानीकृ. 2 युगपद् घंटारवं कृ 8 U. **-s.** घंटानादः. **-my,** *a.* श्यान, सांद्र, घन.
Clamancy, *s.* आवश्यकता
Clamant, *a.* सोत्कंठ-उच्चैः-आक्रोशक.
Clamber, *v. t.* आयामेन आरोहणं कृ 1 P.
Clamour, *v. i.* उत्-आ-क्रुश् 1 P, उच्चैः घुष् 10, आरट् 1 P. **-s.** आ-उत्-क्रोशः, महारवः, उच्चैर्घोषः, जनरवः. **-ous,** *a.* महारव, मुखर, बहुघोष, घोषकर (री *f.*).
Clamp, *v. t.* कीलेन संयुज् 10 or संबंध् 9 P. **-s.** इष्टकाराशिः. 2 कीलकः 3 पादाघातः.
Clan, *s.* गणः. 2 वंशः, कुलं, गोत्रं, वर्गः, संघः, शाखा, जाति *f.*
Clandestine, *a.* निभृत, रहस्य, प्रच्छन्न, गूढ; 'c. marriage' चोरिकाविवाहः. **-ly,** *adv.* निभृतं, गुप्तं, रहः.
Clang, *v. i.* क्रण् स्वन् 1 P, शिंज् 1, 2 A. **-s.** शिंजितं, क्रणितं, तुमुलरवः, शंखनादः.
Clank, *s.* शिंजितं, क्रणितं, झंझनं.
Clap, *v. t.* करतालं दा 3 U or वद् *c.* 2 अकस्मात् संहन् 2 P, संघट्ट् *c.*; न्यस् 4 P. 3 करतालेन प्रशंस् 1 P. 4 (कारागृहे) निक्षिप् 6 P; 'c. wings' उत्क्षिप् 6 P. **-s.** **-ing,** *s.* करतालवादनं, तालः 2 प्रशंसाशब्दः. 3 मेघगर्जितं-नादः, वज्रनिर्घोषः, मेघस्तनितं. 4 ध्वनिः; क्रणितं, संघातशब्दः **-per,** *s.* घंटावादकः, घंटाताडनी.
Clarify, *v. t.* सं-वि-शुध् *c.*, विमलीकृ 8 U, पू 9 U. **-v. i.** विमलीभू 1 P, प्रसद् 1 P.
Clarinet, *s.* वेणुः, वंशः.
Clarion, *s.* तूर्यः; काहलः.
Clash, *v. i.* विरुध् 7 U, विसंवद् 1 P, विप्रतिपद् 4 P, विवद् 1 A 2 संघट्ट् 1 A, आहन् 2 U. **-s.** समाघातः, संघट्टः, विरोधः, विसंवादः, विप्रतिपत्ति *f.* **-ing,** *a.* परस्परविरोधिन्, विरुद्धार्थ, विसंवादिन्.
Clasp, *v. t.* आश्लिष् 4 P, सम्-आ-लिंग् P 1, परिष्वंज् 1 A, परिरभ् 1 A, उपगुह् 1 U; आलिंग् 10; 'c. to the bosom' वक्षसा परिरभ्, क्रोडीकृ 8 U. 2 कुडुपेन बंध् 9 P or पिनह् 4 P. 3 परिरभ् 1 A, परिनिश्चा 3 U: 'c. the hands' हस्तौ समानी 1 P, अंजलिं बंध्. **-s.** आश्लेषः, आलिंगनं, परिरंभः, परिष्वंगः. 2 कुडुपः, गंडः.
Class, *s.* वर्गः छात्रसमूहः, सहाध्यायिवर्गः. 2 श्रेणि-णी *f.*, गणः (of verbs); समूहः संघः; समाहारः 3 जाति *f.* (kind); 'of the c. of beasts' पशुजातीयः. 4 वर्णः जातिः, वर्णः; 'people of the lower c. es' अवरवर्णाः, अंत्यजातीयाः; 'of the same c.' सवर्णः, वर्गीयः, सवर्णः. **-v. t.** **-ify,** *v. t.* वर्गक्रमेण विन्यस् 4 P वर्गशः रच् 10, वर्गीकृ 8 U गणीकृ, गणशः व्यवस्. **-Classical,** *a.* संस्कृत, श्रेष्ठ, प्रथमवर्गीय **Classifier,** *s.* गणकारः; न्यासः.
Clatter, *v. i.* क्रण्-स्वन् 1P, झणझणायते. (D) 2 प्रलप्-जल्प् 1 P. **-s.** क्रणितं, ध्वनिः, तुमुलरवः.

Clause, *s.* पदं, अंगं, अधिकरणं. 2 वाक्यं. 3 नियमः.

Clavated, *a.* ग्रंथिल, जटिल.

Claw, *s.* नखः-खं, नखरः-रं. —*v. t.* नखैः विद् 9 P. 10 or आहन् 2 U.

Clay, *s.* मृद् *f.*, मृत्तिका. 2 पंकः, जंबालः, कर्दमः; 'made of c.' मृण्मय (यी *f.*). —*v. t.* पंकेन लिप् 6 P or दिह् 2 U. **-ish,** *a.* पंकिल, कार्दम (मी *f.*).

Clean, *a.* शुचि, पवित्र, वि-परि-शुद्ध, विमल, निर्मल, धौत (वासः). 2 विमलात्मन्, निर्दोष, अकल्प. 3 श्लक्ष्ण, मसृण. 'To have c. hands,' निर्दोष *a.* भू 1 P; निरागस् *a.* अस् 2 P; "to make a c. breast of,' पापानि निविद् c. or कथ् c.; 'to show a c. pair of heels,' पलाय् 1 A. —*v. t.* See **Cleanse,** below. —*adv.* साकल्येन, अशेषेण, आमूलं, सर्वथा. **-ly,** *a.* निर्मल, पवित्रदेह. —*adv.* शुचि, निर्मलं. **-liness,** *s.* शौचं, शुद्धि *f.*, निर्मलता. **-ness,** *s.* शुचिता, पवित्रत्वं, निर्मलता, &c.

Cleanse, *v. t.* शुध् c., पू 9 U. 2 प्रक्षल् 10, प्र-अव-मृज् 2 P or c., धाव् 1 P, 10, निर्-अव-निज् 3 U, पवित्रीकृ 8 U. **-er,** *s.* शोधकः, पावकः.

Clear, *a.* वि-निर्-अ-मल; प्रसन्न, शुद्ध, अच्छ, विशद, स्वच्छ. 2 स्पष्ट, सुप्रकाश, परिस्फुट, व्यक्त. 3 (fig.) विशद, निश्चित, निष्कालुष्य, निःसंदेह; oft. by निर्-अ- pr.; 'c. sky' अनभ्रं-निरभ्रं-नभः; 'c. from debt' अनृण, ऋणमुक्त; 'c. forest' निष्कंटक-असंबाध-वनं; 'a c. sum' अभग्न, निरवशेष, निरुद्धार. —*v. t.* 'make c.' विशदीकृ 8 U, विवृ 5 U, व्याख्या 2 P. 2 शुध् c., प्रसद् c., विमलीकृ, मृज् 2 P. 3 मुच् 6 P or c.; by निर् pr.; 'c. ed the forest of its thorns' अरण्यं निष्कंटकं चकार; निःक्षत्रियां पृथ्वीं चकार &c.; 'c. from obstacles' विघ्नान् पनी 1 P, निर्विघ्न *a.* कृ; 'c. a doubt' (संशयं) छिद् 7 P, निरस् 4 P. अपनी; 'c. debt' (ऋणं) शुध् c., अपाकृ; निस्तॄ c.; 'c. oneself' आत्मानं निर्दोषं कृ; 'c. up a business &c.' समाप् c., संपूर् 10, निःशेषीकृ; 'c. the throat' उत्कासनं कृ; 'c. the way,' मार्गं अविरुद्धं कृ 8 U. 4 दोषात् मुच् c. 5 लंघ् 1 A, 10; अतिक्रम् 1 U; अति-इ 2 P; निस्तॄ 1 P. 6 लाभं-कलांतरं-आप् 5 P. 7 दूरं अपाकृ 8 U. 'c. out' निर्गम् 1 P. —*v. i.* (up) प्रसद् 1 P, प्रसादं गम् 1 P or ग्रह् 9 P, निरभ्रीभू (as sky); दिशः प्रसेदुः (R. III. 14), गंगा रोधःपतनकलुषा गृह्णतीव प्रसादं (V. 1). **-ly,** *adv.* स्पष्टं, व्यक्तं, स्फुटं. 2 प्रसन्नं, विशदं. 3 निःसंशयं, स्पष्टार्थं. **-ness,** *s.* प्रसादः, वैशद्यं, वैमल्यं, स्वच्छता, शुद्धि *f.* 2 स्पष्टता, व्यक्तता, स्फुटता.

Cleave, *v. i.* संश्लिष् pass., आ-नि-श्लिष्°, लग् 1 P, संलग्नीभू. 2 भिद् pass., स्फुट् 1 P, स्फुट् 6 P. —*v. t.* भिद् 9 P, 10; वि-भिद्-भिद् 7 P, दल् c. (दलयति), विभज् 10. **-er,** *s.* भेदकः. 2 मांसच्छेदिका. **-Cloven,** *a.* विदीर्ण, स्फुटित, विभिन्न; 'c. hoofed' द्विशफ.

Cleft, *s.* दरी, भंगः, संधिः, छिद्रं, रंध्रं.

Clement, Clemency, *See* **Kind-ness.**

Clench, Clinch. *v. t.* (the fist) मुष्टिं बंध् 9 P; 'a blow with the fist c. ed' मुष्टिप्रहारः-संघातः. 2 वज्रमुष्टिना संग्रह् 9 P or पीड् 10. 3 दृढीकृ 8 U, स्थिरीकृ.

Clergy, *s.* पुरोहितवर्गः, धर्माध्यापकवर्गः. **-man,** *s.* पुरोहितः, धर्मशास्त्रज्ञः, धर्मयाजक *m.* **-Clerical,** *a.* याजकीय, धर्मोपदेशकविषय. 2 लेखकसंबंधिन्.

Clerk, *s.* लिपिकारः, लेखकः, कायस्थः. 2 पुरोहितः, धर्माध्यापकः. 3 पंडितः, कृतविद्यः, विद्वस् *m.* **-ship,** *s.* कायस्थकर्मन् *n.*

Clever, *a.* चतुर, दक्ष, विचक्षण, विदग्ध, पटु, मतिमत्, निपुण, कुशल, प्रवीण, विशारद, पेशलमति. **-ly,** *adv.* चतुरं, सपाटवं. **-ness,** *s.* चातुर्यं, वैचक्षण्यं, पाटवं, नैपुण्यं, बुद्धिमत्ता, मतिप्रकर्षः.

Clew, Clue, *s.* सूत्रकोषः. 2 सूत्रं, संचारं, मार्गदर्शकः.

Click, *s.* क्वणत् *a.* ध्वनि *m.*

Client, *s.* आश्रितः, अधीनः, पक्ष्यः, आत्तकः. **-ele,** *s.* अनुसंघात.

Cliff, *s.* प्रपातः, भृगुः, अतटः.

Clift, *s.* *See* '**Cleft**'.

Climate, Clime, *s.* प्रकृति *f.* 2 देशः, प्रदेशः, दिश्.

Climax, *s.* पराकाष्ठा, पराकोटि *f.*, अतिवृद्धि *f.*; 'anxiety reaching its c.' अतिवृद्धिं गतेन रणरणकेन (U. 1); 'the jealousy of her love reached its c.' दूरारूढः प्रणयोऽसहनः (V. 4); सारः (a figure), उत्तरोत्तर उत्कर्षः.

Climb, *v. t.* आ-अधि-रुह् 1 P, अधिक्रम् 1 U, 4 P. —*v. i.* उपरि गम् 1 P. **-er,** *s.* आ-अधिरोहिन् *m.*, आरोढ़ *m.* 2 (plant) व्रतति-ती *f.*, वल्ली, वल्लि-ल्ली *f.*

Clinch, *s.* श्लेषः, द्व्यर्थवाक्यं.

Cling, *v. i.* संश्लिष् 1 P, आ-प्र-सं°, सञ्ज् 1 U; (निवसने कः सजति S. 4), लग् 1 P, सं परि°; 'c.-ing to my neck at the time of going' गमनसमये कंठे लग्ना (Mal. 2), आ-अव-लंब् 1 A, अनुबंध् 9 P; 'c. to hope' आशां न त्यज् 1 P, आशामवलंब्.

Clinic, *s.* रुग्णः, व्याधिग्रस्तः. 2 रुग्णशय्योपांते विद्यार्थिनां चिकित्सोपदेशः. —*a.* **Clinical,** *a.* शय्यागत, शयनग्रस्त.

Clink, *v. i.* शिंज् 1, 2 A. क्ष्विड् 2 P, क्वण् 1 P. –*s.* शिंजितं, क्वणितं, किंकिणीशब्दः. 2 नादः, शब्दः.

Clip, *v. t.* छिद् 7 P; *See* **Cut.** 2 दृढं परिष्वंज् 1 A, उपगुह् 1 U. 3 मुंड् 1 P, ह्रस् c., संक्षिप् 6 P. **–per,** *s.* वंचकः. 2 तुंडिन् *m.* **–ping,** *s.* खंडः, छिन्नं, लवं.

Clique, *s.* गणः, संघः. **–ism,** संघशीलता.

Cloak, *s.* कंचुकः, प्रावारः-रकः, अवगुंठनं. 2 (Pretext, disguise), कपटवेषः, व्याजं, छद्मन् *n.*, मिषं. –*v. t.* प्रावृ 5 U, आच्छद् 10, अवगुंठ् 10.

Clock, *s.* घटी, घटिका, यामनालिका. **–maker,** *s.* घटीकारः. **–work,** *s.* घटीकर्मन् *n.*

Clod, *s.* लोष्टः-ष्टं, मृत्खंडः, मृत्पिंडः. 2 पिंडः; 'c.-pated', 'c. poll' जडः, मृत्पिंडबुद्धिः, स्थूलमतिः. 3 भूमि *f.* 'c. hopper,' कृषीवलः, ग्राम्यः, मंदधीः. –*v. t.* लोष्टैः प्रहृ 1 P. **–dy,** *a.* लोष्टपूर्ण-मय (यी *f.*).

Clog, *v. t.* उप-नि-रुध् 7 U, प्रतिबंध् 9 P, स्तंभ् 9 P. 2 निगडेन बंध् 9 P, शृंखलयति (D.). –*s.* पाशः, निगडः, बंधनं, शृंखला. 2 विघ्नः, प्रत्यूहः, अंतरायः. **–gy,** *a.* प्रतिरोधिन्, विघ्नकर (री *f.*).

Cloister, *s.* मठः, विहारः. **–al,** *a.* विविक्तसेविन्. **–er,** *s.* मुनिः, मठवासिन् *m.*, संन्यासिन् *m.*

Close, *v. t.* अपि-पि-धा 3 U, संवृ 5 U; आ-नि-मील् 1 P or c. (eyes &c.); निमिमील नरोत्तमप्रिया (R. viii. 37,) 'c. ed her eyes in death'. 2 निर्वृत् c., संपद् c., समाप् c., अवसो 4 P. 3 आवेष्ट् 1 A or c., आच्छद् 10, वृ, अवरुंध् 10; 'c. hands' हस्तौ बंध् 9 P; पाणिमुष्टिं कृ; 'c. in' परिवेष्ट् 1 A, परिवृ 5 U; 'c. a bargain,' समयं कृ 8 U; 'with c. ed doors,' गुप्तं, रहसि. –*v. i.* संमिल् 6 P, संगम् 1 A, संपुटी pass. 2 निमील् 1 P, कुड्मलीभू 1 P (lotuses &c.). 3 अवसित-समाप्त-*a.* भू, निवृत् 1 A. निष्पद्-समाप्-pass. **–round,** समंततः परिवेष्ट् 1 A or c., परिवृ 5 U or c. **–with,** *See* **Agree.** 2 संगम् 1 A; बाहूबाहवि युध् 4 A. –*s.* अवसानं, अत्ययः, परिणामः, अंतः, विरामः, क्षयः. 2 निष्पत्ति *f.*, सिद्धि *f.*, समाप्ति *f.*, 'c. of day' दिनात्ययः, सायाह्नः. –*a.* पिहित, संवृत, निमीलित. 2 बद्ध, समंततो निरुद्ध (prisoner &c.). 3 गाढ, अशिथिल, दृढ, घन; 'c. fisted' बद्धहस्तः, बद्धमुष्टिः. 4 अविरल, सांद्र, निबिड, गहन, निरंतर. 5 आसन्न, समीपस्थ, निकटवर्तिन्, समीप, निकट. 6 विविक्त, गुप्त. 7 आसक्त, अभिनिविष्ट, एकाग्र; 'c. application to S'āstras' शास्त्राभिनिवेशः 8 निर्वात, अभ्रित; 'it is c. to-day' निर्वात-अभ्रितं-नभः. 9 संकट, संकुचित, अविस्तृत, संबाध; 'c. fight' रणसंकुलं, बाहुयुद्धं. 10 दृढसौहृद, सुपरिचित. 11 कृपण. 12 (concise) संक्षिप्त. –*adv.* अंतिकं, समीपं-पे, निरंतरं; निकटे; 'c. to the ear' कर्णांतिकं, 'c. by' अनतिदूरे, नातिदूरं. **–ly,** *adv.* निभृतं, गुप्तं, रहसि. 2 निरंतरं, अविरलं, सन्निकृष्टं. 3 प्रयत्नतः, मनोभिनिवेशेन, चित्तासक्त्या. 4 गाढं, दृढं, &c. **–ness,** *s.* समीपता, सन्निकर्षः, सन्निधिः. 2 रहस् *n.*, गुप्ति *f.* 3 घनता, &c. 4 निर्वातता, &c.

Closet, *s.* कोष्ठः, कुटि-टी *f.*, निभृतागारं, वेश्मन् *n.* –*v. t.* कुट्यां गुप् 1 P or निविश् c.

Closure, *s.* पिधानं, वेष्टनं, प्रावरणं.

Clot, *s.* पिंडः, घनता, गुटिका, गुल्मः; 'c. of blood' घनशोणितं; 'c. of hair' जटा. –*v. i.* सांद्रीभू, घनीभू, पिंडीभू, जट् 1 P, स्त्यै 1 A **–ted, –ty,** *a.* पिंडीभूत, घनीभूत, स्त्यान.

Cloth, *s.* वस्त्रं, वासस् *n.*, वसनं, चेलः-लं, पटः, परिधानं, अंबरं; 'fine c.' अंशुकं; 'old, tattered, c. es' कर्पटः, जीर्णवस्त्रं, चीरं; 'unbleached c.' अनाहतं, निष्प्रवाणि, तंत्रकं, नवांबरं. – **Clothe,** *v. t.* (oneself वासः &c. परिधा 3 U or ग्रह् 9 P; वस् 2 A; 'c. ing herself' गृहीतवसना. 2 (वस्त्रेण) आच्छद् 10, परिच्छद्, संव्ये 1 P; वस् c., परिधा c. (धापयति), वेष्ट् 1 A. **–ed, Clad,** *a.* (in) वसान, परिधानवत् (*s.*) in comp. 2 संवीत, आवृत, आच्छादित, परिच्छन्न; सवसन. अनग्न. **–ier,** *s.* वस्त्रकारः, वस्त्रनिर्मातृ *m.* **–ing,** *s.* परिधानं, आच्छादनं, परिच्छदः, वासस् *n.*, वसनं; 'food and c.' ग्रासाच्छादनं.

Cloud, *s.* मेघः, घनः, अभ्रं, जीमूतः, स्तनयित्नुः, बलाहकः, मुदिरः, धूमयोनिः, and combinations of words for 'water' (q. v.) with 'giving' or 'bearing,' जलदः, तोयवाहः, पयोधरः, जलमुच्, वारिदः &c.; 'c. capped' अभ्रंलिह, अभ्रंकष-लिह. 2 (fig.) ज्ञानविघातं, कलुषं. 3 अस्पष्टीकृत् *m.* 4 पटलं. 5 दुर्निमित्तं –*v. t.* प्रच्छद् 10, आवृ 5 U. 2 तिमिरेण आच्छद्. 3 मलिनयति (D) (वक्त्रं). **–ed,** *a.* मेघावृत, अभ्रित, अभ्राच्छादित; तमोवृत, दुर्दिनग्रस्त. **–less,** *a.* निरभ्र, अमेघ, &c. **–y,** *a.* साभ्र, मेघाकीर्ण, समेघ; 'it is c. weather to-day' दुर्दिनमद्य. 2 तमोवृत, तिमिराच्छन्न, अंधकारयुक्त.

Clough, *s.* कंदरः-रा, दरि-री *f.*

Clout, *s.* चीरं, कर्पटः, कंथा. 2 प्रहारः, आघातः. –*v. t.* जीर्णवस्त्राणि संधा-समाधा 3 U. 2 प्रहृ 1 P, आहन् 2 P. **–erly,** *a.* ग्राम्य.

Clove, *s.* (Tree) लवंगवृक्षः. 2 (Spice) लवंगं, देवकुसुमं.

Clover, *s.* त्रिपर्णी, त्रिपत्र.

Clown, *s.* ग्राम्य:, ग्रामिक:, कृषीवल:, कृषक:, जानपद:, पृथग्जन:, असभ्यो जन:. **-ish,** *a.* अशिष्ट, ग्राम्य, असभ्य, ग्रामीण. **-ishly,** *adv.* ग्राम्यवत्, अशिष्टं.

Cloy, *v. t.* उद्विज् c.; पिंडखर्जुरैरुद्वेजितस्य (S. 2) 'c. ed with eating dates;' अतितृप्तिं जन् c. (जनयति).

Club, *s.* यष्टि *f.*, लगुड:, गदा, परिघ:; 'armed with a c.' याष्टिक:, यष्टिधर:. **2** गण:, समाज:, मेलक:. **3** पंक्ति *f.*; सहभोजिनां संसर्ग:. **4** अंश:, भाग:; 'c. foot' स्थूलचरण:. **-***v. t.* बहवः सह 1 P. **2** गुच्छं कृ 8 U, संधि 5 U, मिल् 6 P. **3** स्वयं विभज् c.

Clue, *See* **Clew.**

Clump, *s.* गुच्छ:, संचय:, षंड:. निचय:, गुल्म:, स्तंब:. **-***v. i.* जडगत्या गम् 1 P. **2** समूहं रच् 10.

Clumsy, *a.* अचतुर, अदक्ष, अकुशल, असुंदर, ग्राम्य, स्थूल. **-ly,** *adv.* अदक्षं, दाक्ष्यं विना, अचातुर्ये, अपाटवं. **-ness,** *s.* अचातुर्यं, अपाटवं, &c.

Cluster, *s.* गुल्म:, गुच्छ:, स्तंब:, स्तबक:. **2** संघ:, गण:, समूह:, निवह:, ओघ:, चय:, समुदाय:. **-***v. i.* एकत्र मिल् 6 P, एकीभू 1 P, पिंडीभू. **-***v. t.* संचि 5 U, एकीकृ 8U, पिंडीकृ, समाहृ 1 P.

Clutch, *v. t.* ग्रह् 9 P, धृ 1 P, 10; आक्रम् 1 U, 4 P. **2** मुष्टिं बंध् 9 P. **-***s.*, ग्रह:, ग्रहणं; मुष्टिबंध:. **2** हस्त:, पाणि:, नखं; 'rescued from the c. es of death' मृत्युमुखान्मुक्त:.

Clutter, *s.* कोलाहल:, तुमुलरव:. **-***v. i.* कोलाहलं कृ 8 U. **2** संकुल *a.* भू 1 P.

Coacervate, *See* **Collect.**

Coach, *s* रथ:, प्रवहणं, यानं, वाहनं, शकटिका; 'travels by c.' रथेन संचरति; 'a c. and four' चतुरश्वं यानं; 'c. box' सूतासनं, 'c. ful' पूर्णरथ:, शाकटं; 'c. horse' रथ्य:; 'c. house' रथशाला; 'c. maker' रथकार:; 'c. man' सूत:, सारथि:, यंतृ *m.*

Co-act, *v. i.* सह कृ 8 U. **-ion,** *s.* प्रमाथ:, बलात्कार:. **-ive,** *a.* प्रमाथिन्, बलान्वित, सबल.

Co-adjacent, *a* *See* **Adjacent.**

Co-adjutant, *a.* मिथ:सहाय:, सहकारिन् *m.*

Co-adjutor, *s.* सहाय:, सहकारिन् *m.*

Coagulate, *v. i.* घनीभू 1 P, स्त्यै 1 A. **-***v. t.* स्त्यै c., घनीकृ 8 U, संहन् 2 P. **-ion,** *s.* घनता, संहति *f.*, घनीभाव:, स्त्यानत्वं.

Coal, *s.* खनिजांगार: -रं; 'c. black' अंगारसवर्ण, अति-कृष्ण. **-***v. i.* खनिजांगारान् उपकृ c., 'c. field,' *s.* खनिजांगारक्षेत्रं: 'c. gas,' *s.* खनिजांगारवायु: *m.* 'c. mine,' pit,' अंगारखनि (नी) *f.* '-c. ing station,' अंगारभरणस्थानं.

Coalesce, *v. i.* संमिल् 6 P, संगम् 1 A, एकीभू, संयुज्-संधा-संश्लिष् pass. **-ence,** *s.* संमिलनं. **-ent,** *a.* एकीभवत्, संमिलत्. **-Coalition,** *s.* संयोग:, संश्लेष: मेलनं. संधि:.

Coalise, *v. i.* संधिं कृ 8 U.

Coarse, *a.* स्थूल (cloth &c.); घन, नीरंध्र; अविरल, निबिडस्यूत. **2** असभ्य, अश्लील, ग्राम्य, अशिष्ट. **3** अवाच्य, नीच, निकृष्ट, गर्ह्य; 'c. food' मंदाहार:. **-en,** *v. t.* स्थूली-घनी-कृ 8 U. **-ish,** *a.* ईषत्-स्थूल-घन. **-ness,** *s.* स्थूलता, ग्राम्यता, अश्लीलता, &c.

Coast, *s.* तीरं, तट:-टं, वेला. **2** सीमा. **3** देश:, प्रदेश:. **-***v. i.* उपतीरं नावा संचर् 1 P, नौकां वह् c. **-ing,** *a.* उपतीरं संचरत्. **-line,** *s.* तीररेखा. **-ward,** *adv.* अभितीरं. **-wise,** *adv.* अनुतीरं.

Coat, *s.* कंचुक:, उत्तरीयं, प्रावार:-रक:, निचोल:. 'To turn one's c.,' *v. i.* पक्षांतरं-मतांतरं-कृ 8 U. 'c. of mail', *See* **Armour;** 'c. of arms, *s.* कुलचिन्हं. **2** पटलं, आच्छादनं, पुटं, आवेष्टनं. **3** लो(रो)मन् *n.* (of animals). **-***v. t.* आच्छद् 10, अवगुंठ् 10, आ-सं-वेष्ट् 1 A or c. **2** अनुलिप् 4 P; विलिप् 6 P, चुर् 10. **-ing,** *s.* पटलं, पुटं, आच्छादनं, आवेष्टनं. **2** लेप:, चूर्णं. **3** कंचुकवस्त्रं.

Coax, *v. t.* चाटूक्त्या सांत्व् 10, अनुनी 1 P, उपच्छंद् 10, लल् 10. **-er,** *s.* चाटुकार:. **-ing,** *s.* चाटुवचनं, चाटु *m. n.*, उपच्छंदनं.

Cobble, *v. t.* जीर्णपादुका: नूतना समाधा-संधा 3 U. **2** अपाटवं किंचित्कर्म कृ 8 U. **-er,** *s.* पादुकासंधातृ *m.*: अनिपुण: शिल्पी.

Cobra, *s.* नाग:. फणिन् *m.*, *See* **Snake.**

Cobweb, *s.* जालं, तंतुजालं. **2** संतान:; 'c. of speech' वाग्जालं.

Cock, *s.* कुक्कुट:, शिखिन् *m.*, ताम्रचूड:, नखायुध:, कृकवाकु:; 'c.'s comb' शिखा, चूडा; (fig.) वृथाभिमानिन् *m.*, 'c.-sparrow' चटक:. **2** प्रणाली, जलयंत्रं. **3** पुंगव:, मुख्य:, नायक:. **4** तृणोत्कर:; 'weather c.' वायुध्वज:-ज्ञापक:; 'c. and bull s ory' वृथा-वृथा-कथा; 'c. crowing' कुक्कुटरव:; प्रभातकाल:; 'c. [illegible] 'c. match' प्राणिद्यूतं, ताम्रचूडयुद्धं; समाह्वय:; 'c. pit' कुक्कुटयुद्धस्थानं. **-Cocky,** *a.* स्वायत्त, स्वावलंबिन्. स्वतंत्र. **-***v. t.* उन्नम् c. (उन्नमयति), उत्क्षिप् 6 P, उच्छ्रि 1 U. **-***v. i.* सलीलं चर्-चल् 1 P. **2** दृप् 4 P.

Cockatrice, *s.* अजगर:.

Cock-boat, *s.* उप-क्षुद्र-नौका

Cocker, *v. t.* *See* **Fondle.**

Cockle, *s.* क्षुद्रिका *f.*
Cockloft, *s.* चंद्रशाला, शिरोगृहं.
Cockney, *s.* नगर-पुर-वासिन् *m.*; प्राकृतजनः.
Cock-swain, *s.* क्षुद्रनौकाधिपतिः.
Cocoa-nut, *s.* नारिकेलः-रः, कौशिकफलं; (tree) तृणद्रुमः, शिरःफलः, नालिकेरः-लः, नारि(लि)केरः-केलिः, नारिकेलः-ली, लांगली.
Cocoon, *s.* कोशः-षः.
Coction, *See* Decoction.
Cod, *s.* बीजकोषः, पुटः.
Coddle, *v. t.* ईषत्-शनैः पच् 1 P or क्वथ् 1 P. 2 निपुणं संवृध् c. or पुष् 1, 1 P, 10. –*s.* क्लीबप्रकृति *m.*, क्लैब्यः.
Code, *s.* संहिता; 'c. of laws' धर्म-स्मृति-शास्त्रं, स्मृति *f.*
Codicil, *s.* मृत्युपत्रस्य अनुबंधः or उपलेख्यं.
Coefficacy, *s.* सहकारिता, संयोगिता.
Coefficient, *s.* मानं, गुणः.
Coemption, *s.* अखिलवस्तुक्रयः.
Co-equal, *a.* समानपदस्थ, स-सह-धर्मन्, समानभाग. –ity, समानावस्था; तुल्यभागः, सहधर्मः, तुल्यपदत्वं.
Coerce, *v. t.* सं-नि-यम् 1 P, निरुध् 7 U, निग्रह् 9 P, नियंत्र् 10; *See* **Compel,** as *v.* –ion, *s.* निग्रहः, संयमः; नियंत्रणं. –ive, *a.* नियामक; प्रतिरोधिन्.
Coetaneous, Co-eval, *a.* सम-एक-कालीन; समान-तुल्य-वयस्क, सवयस्. –*s.* वयस्यः, स-तुल्य-वयस् *m.*
Co-exist, *v. i.* सम-एकत्र वृत् 1 A or भू 1 P, एक-काले भू or जीव् 1 P. –ence, *s.* एक-कालावस्थानं, सहवर्तनं, सहजीवनं. –ent, *a.* सहवर्तिन्-जीविन्.
Co-extend, *v. i.* समं विस्तॄ pass. or व्याप् 5 P. –Co-extension, *s.* अभिव्याप्ति *f.*; समविस्तारः.
Coffee, *s.* काफी नाम फलं or बीजं or पेयं.
Coffer, *s.* [illegible]
Coffin, *s.* शवाधारः, शवभाजनं –*v. t.* शव भाजने निधा 3 U.
Cog, *v. t.* Flatter, q. v.; 'c. a die' कपटं कृ 8 U, 'c. a wheel' नेमिं मदन्तां कृ. 2 चक्रं लभ् c. –*s.* नेमिदंतः.
Cogent, *a.* प्रबल, [illegible] निश्चायक. –ly, *adv.* निश्चयं –Cogency, *s.* बल, सामर्थ्य, प्रभावः, शक्ति *f.*
Cogitation, *s.* [illegible]
Cogitate, *v. i.* चिंत् 10 ध्यै 1 P, विचर् *c.*, विमृश् 6 P अनुध्या 1 . वितर्क् 10. –ion, *s.* चिंता, [illegible] आलोचनं, विमर्शः, [illegible]. –ive, *a.* चिंतापर 2 [illegible]. –Cogitable, *a.* चिंत्य, [illegible].
Cognate, *a.* सजाति, एकजातीय, सगोत्र, संबंधिन्, तुल्य-समान-वंश. –*s.* सजाति *m.*, ज्ञाति *m.* –ion, *s.* बंधुता, ज्ञाति-भावः, संबंधः सजातीयत्वं.
Cognition, *s.* ज्ञानं, प्रज्ञानं.
Cognis(z)e, *v. t.* अभिज्ञा 9 U. –able, ज्ञेय, बोध्य. 2 विचार्य, अनुसंधेय.
Cognizance, *s.* विचारणं, अनुसंधानं, चर्चा, अनुयोगः. 2 चिह्नं, लक्षण, संज्ञा, लिंगं; 'take c. of' अनुसंधा 3 U, विचर् c., अनुयुज् 7 A, ज्ञा 9 U. अवेक्ष् 1 A. 'To have c. of,' अभिज्ञा 9 U.
Cognomen, *s.* उप-कुल-नामन् *n.*
Cohabit, *v. i.* संवस् 1 P; अभिगम् 1 P (with another's wife), संभोगं कृ 8 U.
Coheir, *s.* सहदायभाज् *m.*
Cohere, *v. i.* संसंज् संयुज्-संसक्त संश्लिष् pass. 2 युज् pass. –ence, *s.* संसक्ति *f.*, संश्लेषः, संयोगः. 2 संबंध, संगति *f.*, अन्वयः, संदर्भः, अविरोध. –ent, *a.* संसक्त, संश्लिष्ट, संहत, संलग्न. 2 संगत, अविरुद्ध संबद्ध, अनुरूप, सान्वय. –Cohesion, *s.* संसक्ति *f.*, संयोगः, संश्लेषः, संलग्नता. –Cohesive, *a.* सांद्र, संलग्नशील, स्निग्ध.
Cohobate, *v. t.* पुनः संधा 3 U.
Cohort, *s.* सैन्यदलं-गुल्मं
Coif, *s.* मुकुटः, शिरस्त्रं शिरोवेष्टनं.
Coil, *s.* मंडलं, व्यावर्तनं, आवेष्टनं; गुणः (of a rope). 2 तुमुलं, व्यस्तता; 'mortal c.' नश्वरदेहः. –*v. t.* मंडलीकृ 8 U, वर्तुलीकृ पुटीकृ; व्यावृत् c., आ परिवेष्ट् c.
Coin, *s.* मुद्रा, नाणकं, टंकः; 'copper c.' पणः; 'I paid him in his own c.' यथैव स मयि व्यवहरत्तथैवाहं तस्मिन्नाचरं. –*v. t.* मुद्र[illegible] ( ), मुद्रया अंक् 10. 2 सृज् 6 P, कल्प् c., निर्मा 3 A. –age, *s.* मुद्रा, कल्पना, सृष्टि *f.* –er, *s.* मुद्राकारः, कल्पकः.
Coincide, *v. i.* एकीभू 1 P, समाप् 1 A, सं-मनिपत् 1 P संगम संयुज्-pass. 2 संवद् 4 A एकचित्तीभू; *See* Agree 3 अनुरूप *a.* भू, युज् *pass.* अनुवृत् 1 A संवद् 1 P, तुल्य-समान- . भू. –ence, *s.* संनिपातः, संगमः, संयोगः. 2 संमति *f.*, ऐकमत्यं, ऐक्यं, एकचित्तता. 3 संवादः, अनुरूपता, आनुरूप्यं. 4 दैवयोगः घटनं; 'by an unlucky c.' दुर्दैवात् –ent, *a.* संपातिन्. 2 समकालीन. 3 अविरुद्ध, अनुरूप, संवादिन्
Coinstantaneous, *a.* समकालीन.
Coir, *s.* नारिकेलत्वक्तंतु *m.*
Coition, *s.* मैथुनं, सुरतं रतिक्रिया.
Coke, *s.* अर्धदग्धांगारोच्छिष्टं.
Colaborator(teur), *s.* सह-कारिन्-कृत् *m.*
Colander, *s.* चालनी, शोधनी तितउः
Colation, *s.* शोधनं, चालनं
Cold, *a.* शीत, शिशिर, हिम, शीतल, तुषार, जड, 'c. rayed' (moon) हिमांशुः, शीतकरः, &c.; 'c. season' हेमन्तः, शिशिर,

शीतकालः. 2 (fig.) अनादरयुक्त, विरक्त, निःस्नेह, निरुत्साह, उदासीन ; 'gave me a c. welcome' निरुत्साहं स्वागतं मां व्याजहार, मत्संभावनायां तेन औदासीन्यं दर्शितं ; 'in c. blood' प्रकोपवं विना, पूर्वसंकल्पेन; 'c. blooded or hearted,' *a.* निर्दय, निष्ठुर; 'to take or catch c.,' *v. i.* शीताकुल *a.* भू 1 P. 'to give the c. shoulder to,' अनादरं दृश् c. 2 निराकृ 8 U. -*s.* शीतं, शैत्यं; शिशिरः, हिमः. 2 प्रतिश्यायः ; 'suffering from c.' शीतार्त. -ly, *adv.* शीतं, शैत्येन. 2 निरुत्साहं, विरक्तं, उदासीनतया. -ness, *s.* शीतता, हिमता, शैत्यं. 2 अनादरः, निःस्नेहता, विरागः, विरक्ति *f.*, औदासीन्यं.

Colic, *s.* शूलः-लं, उदर-जठर-व्यथा-शूलं. -*a.* उदरव्यथाजनक.

Collapse, *v. i.* क्षय लयं गम् 1 P, अवसद् 1 P. 2 संहृ-श्र. pass.; संकुच् 1 P; सं-साके-पत् 1 P -*s.* संकोचः. 2 संहारः, क्षयः, लयः, अवसादः. 3 सन्निपातः, शारीरपातः लयः

Collar, *s.* ग्रैव-वेयं, कंठभूषणं, माला. 2 कंठपाशः. -*v. t.* ग्रैवेयं-ग्रीवा-धृ 1 P. -bone, *s.* ग्रीवास्थि *n.*, जत्रु *n.*

Collate, *v. t.* समवलोक् 10, परीक्ष् 1 A; उपमा 3 A, संशुध् c. 2 वृत्तिं प्रदा 3 U. -ion, *s.* संपरीक्षणं, संशोधनं, उपमानं. 2 कल्पवर्तः, प्रातभक्ष्यः फलादिसंभारः, लघ्वशनं. 3 वृत्तिप्रतिपादनं.

Collateral, *a.* आनुषंगिक-प्रासंगिक (की *f.*) असरल. 2 भिन्नशाख, प्रतिलोम. 3 समानादृक, सपिंड. 4 पार्श्वापार्श्विगत. -*s.* समकालीनः. 2 सपिंडः -ly, *adv.* पार्श्वापार्श्वि ; असरलं, वक्रं, प्रसंगतः.

Colleague, *s.* सहायः, सहकारिन् *m.*, समानव्यापारः, एकाधिकारिन् *m.*

Collect, *v. t.* चि 5 U, अव-वि-सं-नि-°, समाह 1 P, संग्रह् 9 P, समाह 1 P, संभृ 3 U, समाक्षिप् 6 P, पिंडीकृ 8 U, राशीकृ, एकत्र कृ. 2 अनुमा 3 A, ऊह् 1 A, अवगम् 1 P; 'c. ed his mind into itself' चित्तं समाधाय; 'c. oneself' संयम्-वश्-नी-स्थ् 1 A or आ-मानं-धृ 4 P, चेतः सं-धा 3 U. -*v. i.* संमिल् 6 P, समागम् 1 P, *See* **Assemble.** -ion, *s.* गणः, संघः, समवायः, निवहः, चयः, समूहः, ओघः, समुच्चयः, समाहारः, संग्रहः, वृंदं. -ive, *a.* समवेत, संहत, समस्त, एकीभूत, समवायिन्, एकीकृत. -ively, *adv.* एकीभूय, संभूय; संघशः, साकल्येन. -or, *s.* संग्राहकः, संचेतृ *m.* 2 करग्राहकः

College, *s.* विद्यालय. यं, पाठशाला. 2 मठः, विहारः. 3 सभा, समाजः, जनसमूहः. -Collegian, *s.* विद्यार्थिन् *m.*, छात्रः ; विद्यालयसभ्यः.

Collet, *See* **Collar.**

Collide, *v. i.* सं-समा-घट् 2 U, संघट् 1 A or c.; संवृत् 9 P. -Collision, *s.* संघट्टः, समाघातः, प्रतिघातः, संमर्दः, संघर्षः.

Colligation, *s.* संबंधः.

Collimation, *s.* संधानं.

Collinear, *a.* समरेखास्थित.

Collocate, *v. t.* सं-प्रति-स्था c. (स्थापयति), निधा 3 U, न्यस् 4 P, निविश् c. 2 नियुज् 7 A, 10. -ion, *s.* स्थापनं, निवेशनं.

Collocution, *s.* संभाषणं, कथाप्रसंगः, कथायोगः, संवादः, संकथा.

Collogue, *See* **Flatter.**

Colonnade, *s.* समानांतरस्तंभपंक्ति *f.*

Collop, *s.* मांसखंडः-लवः.

Colloquy, *s.* संलापः, संकथा, संभाषणं, संवादः. -al, *a.* आलापविषय, भाषणप्रयुक्त ; 'c. style' संलापोचिता भाषासरणिः.

Collude, *v. i.* पक्षपात-कूटं कृ 8 U ; वञ्च् 10-कूट-योगं कृ. -Collusion, *s.* पक्षपातः, कूटसंविद् *f.*; प्रतारणा, शाठ्यं, कपटं.

Colly, *s.* अंगारमलं-किट्टं. -*v. t.* अंगारेण कृष्णीकृ 8 U. -ed, *a.* अंगारमलिन, मलीमस, कृष्ण. -er, *s.* अंगारखनकः-विक्रेतृ *m.* -y, *s.* अंगारोत्पत्तिस्थानं.

Collyrium, *s.* अंजनं, कज्जलं, नेत्ररंजनं.

Colon, *s.* द्विबिंदुः. 2 महदंत्रं.

Colonel, *s.* गुल्मपतिः, सैन्यदलाध्यक्षः, वाहिनीपतिः.

Colony, *s.* अधिनिवेशः ; वासितः प्रदेशः. 2 गणः, संघः ; *See* **Collection.** -ist, *s.* अधिवासिन् *m.*, अधिनिवेशिन् *m.* -ize, *v. t.* अधिवस् 1 P, अधिनिविश् 6 P, अध्यास् 2 A, (with acc.).

Colossus, *s.* बृहत्प्रतिमा, भीमविग्रहा मूर्तिः. -Colossal, *a.* बृहत्काय, अतिमानुषाकार, भीमविग्रह.

Colour, *s.* वर्णः, रागः, रंगः, 2 वर्णकः-का, लेपः ; 'change c.' विवर्णीभू ; 'ruddy c. on face' लोहिताननं; 'without c.' पांडु, विवर्ण. 3 अप-व्यप-देशः, छद्मन् *n.*, छलं, व्याजः. 4 पताका, ध्वजः, केतुः. 'C. blind,' *a.* वर्णविवेकाक्षम, 'to come off with flying c. s.' विजयिन् *a.* भू 1 P, पताकां उद्धरन्त *a.* आगम् 1 P; कार्यसिद्धिप्रकट् 10, 'to come out in one's true c. s.' स्वभावं प्रकट् 10; 'fast c.' स्थायिन् *a.* वर्णः; to fight under false c. s.' स्वहेतुगोपनाय व्याजं पुरस्कृ 8U; 'to give c.' उचितत्वं आरुह् c.; 'high c.' ताम्रवर्णः; 'to lose c.' विवर्ण *a.* भू 1 P, नष्टसौंदर्य *a.* भू 1 P. ; 'off c.' अप्रसन्नः, 'to paint in bright c. s.' वृध् 10, अतिशयोक्त्या वद् 1 P, 'to show one's c. s,' स्वमतं-स्वभावं-आविष्कृ 1 P; 'to stick to one's c.'

s. स्वपक्षं-स्वमतं-पुष्टं अवलंब् 1 A; 'under c. of' (in comp.) ex. by 'व्याजेन or छलेन'; 'without c.' निर्व्याजं. —v. t. रंज् c., वर्ण् 10, चित्र् 10. 2 व्यप-अप-दिश् 6 P, आच्छद् 10, छद् c. (छादयति). 3 सत्यवदाभास् c., सत्याभास a. कृ 8 U, सत्यसन्निभ a. कृ. —v. i. रंज् pass. 2 लज्जाया अरुणवदन a. भू, व्रीडित a. भू, लज्ज् 6 A. —ing, s. रंजनं; 'art of c.' चित्रकर्मन् n., आलेख्यकरणं, आलेख्यविद्या. 2 वर्णनं; अलंकारः. —ist, s. वर्णिन् m., रंजकः. —less, a. अवर्ण, विवर्ण, वर्णहीन. —Colorate, a. सराग, रागयुक्त. —Colorific, a. वर्णद.

Colt, s. अश्वशावः, किशोरः. 2 चपलः, प्रमत्तः. —ish, a. चपल, तरल, चंचल, लोल.

Colter, s. हलवृंतः, फालवृंतः.

Columbarium, Columbary, s. कपोतागारं, विटंकः. —Columbine, a. कपोतसदृश, कपोतीय.

Column, s. स्तंभः, यूपः, स्थाणुः, स्थूणा. 2 व्यूहः; सैन्यभागः. 3 पत्रभागः, धारा; 'c. of smoke' धूमराशिः, धूमोत्पीडः.

Coma, s. अतिनिद्रा. —tose, a. अतिनिद्रातुर.

Comate, s. सहायः, सहवासिन् m.

Comb, s. प्रसाधनी, कंकतः-तिका, केशमार्जनी. 2 कुक्कुटचूडा-शिखा. 3 दरी. —v. t. प्रसाध् c., मृज् 2 P, विजटीकृ 8 U. —maker, s. कंकतकृत् m.

Combat, s. युद्धं, संग्रामः, समरं; *See* **Battle;** 'single c.' द्वंद्वयुद्धं; 'hand-to-hand-c.' बाहूबाहवि, बाहुयुद्धं; 'mingled c.' (melee) तुमुलं, रणसंकुलं. —v. t. युध् 4 A, विग्रह् 9 P, विवद् 1 A. —v. i. प्रतियुध्, प्रतिरुध् 7 U, प्रतिबंध् 9 P. 2 बाध् 10, निरस् 4 P, निराकृ 8 U; 'c. one's passions' संयम् 1 P, निग्रह् 9 P. —ant, s. योधः, योद्धृ m., भटः; वीरः. —ive, a. कलहप्रिय.

Combine, v. t. संयुज् 7 U, 10, संश्लिष् c., संधा 3 U, संमिश्र् 10, एकीकृ 8 U. —v. i. मिल् 6 P, संभू 1 P, संगम् 1 A; संहत-समवेत a. भू, एकीभू; संयुज्-संधा-संहन्-संसृज् pass.; 'all things c. ed to ruin him' सर्वमेव तस्य नाशायाकल्पत; 'having c. ed' संभूय, मिलित्वा. —ation, s. संहति f., संयोगः, संसर्गः, संधिः, संघातः, संगः, सहायत्वं, संश्लेषः, व्यतिकरः, समवायः; (of letters) संधिः; 'working by c.' संभूय समुत्थानं; 'in c. with his brothers' भ्रातृसंघातवान् (राजा).

Combustible, a. दाह्य, दाहग्राहक; ज्वलनार्ह, दहनशील. 2 (fig.) शीघ्रकोपिन्, क्रोधिल. —s. दाह्यः पदार्थः.

Combustion, s. दाहः, दहनं, ज्वलनं, प्लोषः.

Come, v. i. आगम् 1 P, आया 2 P, आ-इ 2 P; उपस्था 1 U, आव्रज् 1 P, आ-अभि-पद् 4 A. 'c. what may' यद्भावि तद्भवतु; 'c. harm, c. good' यद्भावि तद्भवतु शुभमशुभं वा. —about, संवृत् 1 A, संभू, आपद् 1 P; 'c. across,' *See* **Meet.** —back, निवृत्, प्रत्यागम्. —at, or by, *See* **Get.** —down, अवतॄ 1 P, अवरुह् 1 P, अवपत् 1 P. —down upon, (सहसा-रभसा) अवस्कंद् 1 P, आपत् 1 P, अभिद्रु 1 P, आक्रम् 1 U, 4 P. 'c. down with' देयं दा 3 U. —forth, निर्गम्, निःसृ 1 P, 'c. in' वशी भू 1 P; वशं गम् 1 P. —into, प्रविश् 6 P; 'c. into trouble' विपदभिभू, आपद्ग्रस्त a. भू. —near, *See* **Approach.** —of, *See* **Arise.** —off, out, निष्क्रम्; निर्गम्, उद्गि 2 P; 'came out successful' जयी बभूव. 2 प्रवृत्, संपद्, निवृत्, अवसो pass. 'c. out' प्रसिद्धिं गम्. —over, आक्रम् 1 U. 'c. round,' प्रकृतिं आपद्. —short, न्यूनीभू. —to, सकाशं आगम्-या-इ, आप् 5 P, प्रकृतिमापद् 4 A, *See* **Amount;** 'c. to a head' पाकं व्रज् 1 P; सपूय a. भू; 'c. to blows' अन्योन्यं प्रहर्तुं आरभ् 1 A. 'c. to life' उज्जीव् 1 P; 'came to nothing' तस्य कोऽपि परिणामो नासीत्, निष्फलं-निर्गुणं बभूव; 'c. to pass,' आपत्, समापद्, संवृत्; 'c. to oneself' प्रकृतिमापद् 4 A, संज्ञां-चेतनां-लभ् 1 A or प्रतिपद्, प्रकृतौ स्था, 'c. to terms,' संधिं कृ 8 U. 'c. under' समाविश् 6 P. —up to, समुपागम्, समाया, समुपस्-सृ. —up with, आसद् c., आप्. —upon, आ-समा-पत्, उपस्था, आक्रम्. —ing, s. आगमनं. —a. (to come) आगामिन्, 'on the c. Monday' आगामिनि सोमवासरे; भाविन्, उत्तर; 'time to c.' उत्तरकालः; 'c. generations' s. पुत्रपौत्राः; उत्तरकालीना जनाः.

Comedy, s. भाणः, प्रहसनं, हर्षप्रधानं नाटकं, —ian, s. नटः, कुशीलवः, नर्तकः, वैहासिकः. 2 प्रहसनकृत् m.

Comely, a. चारु, सुंदर (री f.), सुरूप, *See* **Beautiful.** —ness, s. चारुत्वं; *See* **Beauty.**

Comestible, s. *See* '**Eatable**'.

Comet, s. धूमकेतुः, केतुः, उत्पातः, उल्का.

Comfit, Comfiture, s. मिष्टान्नं, मोदकः.

Comfort, v. t. समा-आ-श्वस् c., सांत्व् 10. 2 संतुष् c., आनंद् c., हृष् c., सुखं दा 3 U, सुखिन्-a. कृ 8 U; 'c. yourself' समाश्वसिहि. —s. आश्वासनं, सांत्वनं; संतोषणं. 2 सुखं, सुस्थता, सौख्यं, स्वास्थ्यं, निर्वृति f. —able, a. सुखकर (री f.), सुखद; सुखशयितं प्रष्टुं (S. 4) 'to ask whether she had a c. sleep.' 2 आश्वासक, शांतिद, क्लेशापह, दुःखविनोदक. —ably, *adv.*

सुखं, यथासुखं; निकामं; 'I can't sleep c. even at night' रात्रावपि निकामं शयितव्यं नास्ति (S. 2). **-er,** *s.* आश्वासकः, संतोषकः, शोकापहर्तृ *m.*, सांत्वयाङ्कः. **2** और्णं कंठावगुंठनं. **-less,** *a.* निरानंद, सुखरहित, संतोषहीन.

Comic, Comical, *a.* हासजनक, हासकर (री *f.*), हास्योत्पादक. **2** अपरूप, असंगत, **-ity, -alness,** *s.* हास्यता, कौतुकं; अपरूपता.

Comity, *s.* *See* **Civility.**

Comma, *s.* स्वल्पविरामः.

Command, *v. t.* आज्ञा c. (आज्ञापयति) आदिश् 6 P, व्या-सं-समा-°, विधा 3 U, शास् 2 P, नियुज् 7 A, 10. **2** अधिष्ठा 1 P, अध्यास् 2 A; ईश् 2 A, प्रभू (with gen.); 'Rákshasas c. ed by 2 chieftains' नायकाभ्यामधिष्ठिता राक्षसाः. **3** नियम् 1 P, निग्रह् 9 P; *See* **Control. 4** आत्मवशं नी 1 P, स्वायत्तीकृ 8 U. **5** अवलोकृ 10. 'sitting at a window c. ing (the view of) a well' दीर्घिकावलोकनगवाक्षगता (M. 1); 'good forms c. respect' आकृतिविशेषेष्वादरः पदं करोति (M. 1); पदं हि सर्वत्र गुणैर्निधीयते (R. III. 62) 'c. notice or attention.' **-s.** आदेशः, निदेशः, शासनं, नियोगः. **2** अधिकारः, प्रभुत्वं, आधिपत्यं, अधिष्ठातृत्वं; 'has Rákshasas under his c.' तस्यादेशमनुवर्तमाना राक्षसाः or स राक्षसानामधिपतिः-नायकः-अधिष्ठाता; 'at c.' वशेस्थित, *a.*; 'under one's c.' वशीकृत, स्वाधीन; 'to the c. of the army' सैनापत्ये; 'bring under one's c.' आत्मवशं नी, स्वाधीन *a.* कृ; 'though I have no c. over language' तनुवाग्विभवोऽपि सन् (R. I. 9); 'who has perfect c. over language' यं वाग्वश्यैवानुवर्तते (U. 1). **-ant, -er,** *s.* आज्ञापकः, आदेष्टृ *m.* **2** पतिः, अध्यक्षः, नायकः, नीः in comp.; c. of an army चमूपतिः, सेनानीः, सेनाध्यक्षः. **er-in-chief,** सेनापतिः, सेनाध्यक्षः. **-ment,** *s.* आज्ञा, विधिः, सूत्रं. **2** चोदना, शास्त्र-धर्म-आज्ञा.

Commemorate, *v. t.* स्मरणार्थं उत्सवं कृ 8 U. or आचर् 1 P; संकृत् 10, संस्तु c., वर्ण् 10. **-ion,** *s.* उत्सवकरणं, स्मरणोत्सवः; 'in c. of' स्मरणार्थं, समुद्दिश्य. **-ive,** *a.* स्मारक, स्मरणकृत्.

Commence, *v.* आ-प्रा-रभ् 1 A, प्र-उप-क्रम् 1 A, प्रवृत् 1 A, व्यवसो 4 P. **2** अनुष्ठा 1 P, प्रस्तु 2 U. **-ment,** *s* आरंभः, उपक्रमः, प्रस्तावः, मुखं, आदि *m.* **2** आमुखं, प्रस्तावना (in dramas). **3** अनुष्ठानं, प्रवृत्ति *f.*, वर्तनं; 'from the c.' आमूलात्, आदितः.

Commend, *v. t.* प्रशंस् 1 P, स्तु 2 U, श्लाघ् 1 A, कत्थ् 10, वर्ण् 10. **2** सम्-अर्प् c. (अर्पयति), हस्ते निक्षिप् 6 P, अधीन *a.* कृ 8 U; 'thy speech does not c. itself to me' त्वद्वचो नाभिनंदामि (S. 2). **-able,** *a.* प्रशस्य, श्लाघ्य, स्तुत्य. **-ation,** *s.* श्लाघा, प्रशंसा, स्तुति *f.* **-atory,** *a.* श्लाघासूचक, प्रशंसाकर (री *f.*), स्तुतिद्योतक. **-er,** *s.* प्रशंसकः, स्तावकः.

Commensurate, *v. t.* अनुरूप-अनुगुण-*a.* कृ 8 U. **2** अपवृत् c. **-a., -Commensurable,** *a.* अनुरूप, अनुगुण, सदृश (शी *f.*), सम, तुल्य. **2** सापवर्त.

Comment, *v. i.* व्याकृ 8 U, व्याचक्ष् 2 A, विवृ 5 U, भाष्यं लिख् 6 P. **2** निरूप् 10, चर्चां कृ, परीक्ष् 1 A, अनुसंधा 3 U. **-ary,** *a.* टीका, व्याख्या, वृत्ति *f.*, भाष्यं. **2** निरूपणं, परीक्षणं, चर्चा. **-ator, -er,** *s.* भाष्यकृत्-कारः, व्याख्यातृ *m.*, टीकाकारः-कृत्.

Commentitious, *a* कृत्रिम, कल्पित.

Commerce, *s.* वाणिज्यं, क्रयविक्रयः, निगमः. **2** व्यवहारः, संगमः-ति *f.*, संसर्गः. **-v. i.** वाणिज्यं कृ 8 U, पण् 1 A, व्यवहृ 1 P. **-ial,** *a.* वाणिज्य-विषयक-संबंधिन्; 'c. people' वाणिज्यपरायणा नराः.

Commination, *s. See* **Curse, Threat.**

Commingle, *v. t.* संयुज् 7 U, 10, संमिश्र् 10. एकीकृ 8 U, संकृ 6 P; *See* **Unite.**

Comminute, *v. t.* चूर्ण् 10, पिष् 7 P, क्षुद् 7 U. **-ion,** *s.* चूर्णनं, पेषणं, क्षोदः.

Commiserate, *v. t.* दय् 1 A, (with gen.), अनुकंप् 1 A. **-ion,** *s.* दया, अनुकंपा, करुणा. **-ive, Commiserable,** *a.* करुणात्मक, अनुकंपाशील, सदय, दयार्द्र.

Commissary, *s.* सैन्यानां भोजनादि परिकल्पकः **2** *See* **Deputy. -Commissariat,** *s.* सैन्यानां भोजनाद्यधिकारः. **2** सैन्यानां भोजनाद्यधिकृतः.

Commit, *v. t.* कृ 8 U, आचर् 1 P, अनुष्ठा 1 P, वि-धा 3 U. **2** (Entrust) ऋ c. (अर्पयति), न्यस् 4 P, निक्षिप् 6 P. **3** नियुज् 7 A, 10, समादिश् 6 P, प्रतिपद् c.; 'c. to memory' कंठस्थ *a.* कृ; अभ्यस् 4 U; 'c. to prison,' कारागारं प्रविश् c., आसिध् 1 P; 'c. to writing' अभिलिख् 6 P. लेख्यं-पत्रे आरुह् c. (पत्रमारोप्य दीयतां प्रत्ययश्रितं कर्म S. 6). पत्रे निविश् c. (पत्रे निवेशितमुदाहरणं प्रियायाः V. 2), पत्रे न्यस् c. **-tal,** *s.* आचरणं, करणं, अनुष्ठानं. **-tee,** *s.* कार्यसंपादिका सभा, नियुक्तजनाः. **-ment,** *s.* आसेधः, निरोधः, काराप्रवेशनं. **-Commission,** *s.* आचरणं, करणं. **2** समर्पणं, निक्षेपः, न्यासः **3** नियोगः, व्यापारः, अधिकारः **4** आज्ञा-शासन-पत्रं, आदेशः. **5** परार्थ-विक्रयः **6** नियुक्तजनाः; 'c. in the

army ' सेनायां पर्द्. **-v. t.** निवुच् 7 A, 10, अधिविश् 6 P, अधिकृ 8 U. **-er, s.** निवेशयितृ m., अधिकारिन् m.

Commix,-ture, *See* **Mix,-ture.**

Commode, s. स्त्रीमस्तकाभरणं.

Commodious, a. उचित, उपयुक्त, योग्य. 2 सोपकरण, यथायुक्त-योग्य. **-ly, adv.** युक्तं, योग्यं. **-ness, s.** योग्यता, औचित्यं, &c.

Commodity, s. पण्यं, द्रव्यं, क्रयवस्तु n., भांडं.

Common, a. साधारण (णी f.), सामान्य, सर्वीय, सार्वलौकिक (की f.). 2 प्राकृत, ग्राम्य ; 'c. man' प्राकृतः, पृथग्जनः, वृषलः. 3 प्रसिद्ध, व्यावहारिक (की f.), बहुशः कृत-दृष्ट 4 बहुस्वामिक. 5 सुलभ ; 'c. report' जनप्रवादः ; 'c. food' गणान्नं, सहभोजनं ; 'c. road' प्रचारः ; 'in c.' सामान्येन; 'who have made c. cause with us' अस्माभिः सहैककार्याणां (Mu. 2). **-s.** प्रचारः, सर्वसाधारणं क्षेत्रं. **-alty, s.** प्रजा, लोकाः, अवरवर्णाः **-law, s.** देशाचारः, देशव्यवहारः-विधिः **-ly, adv.** सामान्यतः, प्रायः, साधारण्येन, बहुशः. **-place, a.** प्रसिद्ध, प्राकृत. **-wealth, s.** प्रजाधीनं राज्यतंत्रं. प्रजाप्रभुत्वं ; 'c. (of ants)' समूहः, स्वतंत्रो गणः

Commorancy, s. वासः, वसति f.

Commotion, s. क्षोभः, विप्लवः; प्रकोपः, कलहः.

Commune, v. i. संभाष् 1 A, संमंत्र् 10 A, संवद् 1 P; व्यवहृ 1 P; व्यासादयो देवर्षिभिः प्रत्यक्षं व्यवहरंति (S. B. 313) 'c. directly with Gods.' **-s., -ion, s.** संभाषणं; संवादः. 2 व्यवहारः. 3 संसर्गः, संगः, संगमः. **-ity, s.** समाजः, जनसमूहः, प्रजाजनः, जनता, गणः. 2 सामान्यं, साधारण्यं; ऐक्यं, साम्यं.

Communicate, v. t. कथ् 10, निविद् c., आख्या 2 P, आचक्ष् 2 A. (with dat. of person), विद् 5 U, प्रकाश् c., वद् 1 P, विज्ञा c (ज्ञापयति), संदिश् 6 P. 2 वितॄ 1 P (with loc.), दा 3 U, प्रतिपद् c. (with dat.). **-v. i.** संगम् 1 A, समागम्, संयुज् pass; 'c. ing with Sindhu' सिंधुनद्येन संगत-संगच्छमान. 2 संलप् 1 P. संवद् 1 P, संभाष् 1 A; व्यवहृ 1 P. 3 संचर् 1 P. **-ion, s.** कथनं, निवेदनं, विज्ञापनं: संदेशः, लेखः, लेख्यं. 2 दानं, वितरणं. 3 संगमः; संसर्गः, संव्यवहारः. 4 संकथा, संलापः, संवादः. 5 सामान्यपथः. 6 संचारः. **-ive, a.** संभवान-संवादि-शील ; 'not c.' मितवाच्, वाग्यत.

Commute, v. i. परिवृत् c., विनिमे 1 A, विपर्यस् 4 P, or c., प्रतिदा 3 U. **-ation, s.** परिवर्तनं, विनिमयः. 2 विनिमयः, वि-परिणामः, विपर्ययः ; 'c. of a curse' उच्छापः.

Compact, a. घनसंहत, निबिड, घन, सांद्र, दृढ, अनंतर, अविरल. **-s.** नियमः, समयः, संविद् f., अभ्युपगमः, प्रतिश्रवः ; 'a written c.' नियमपत्रं; 'make a c.' संविदमभ्युपगम् 1 P. प्रतिश्रु 5 P. **-v. t.** संहन् 2 P, संधा 3 U, संश्लिष् c., घनीकृ 8U. **-ly, adv.** दृढं, निबिडं, घनं. **-ness, s.** संहति f. निबिडता, &c.

Companion, s. सखि m., सहचरः, मित्रं, वयस्यः, सहायः; सुहृद् m.; 'with Madhu for a c.' मधुसहायः, मधुद्वितीयः; 'c. of the king' (in love matters) नर्मसुहृद्-सचिवः ; 'c. of youth' बालसहचरः ; 'c. at school' सहाध्यायिन् m., 'c. in arms' सहयोद्धृ m. 'c. in joy and sorrow' समदुःखसुखः ; **-ship, s.** साहचर्यं, साहाय्यं, संसर्गः, संगति f.

Company, s साहचर्यं, संगति f., समागमः, संसर्गः, संवासः, सहवसति f. 2 जनसमूहः, परिषद् f., समाजः ; दलं, वृंदं, गणः, पंक्ति f., वर्गः; 'c. of soldiers ; सैन्यदलं-गुल्मः 'c. of traders' श्रेणी, नैगमाः ; 'not admissible into c.' अपांक्तेयः; 'keep or bear c. with' सह वस्-चर्-1 P, संगम्-अनुव्रज् 1 P, *See* **Associate.**

Compare, v. t. तुल् 10 (तुलयति), उपमा 3 A; 'c. ed with the moon' शशांकेन तुलितं ; समीकृ 8 U, सदृशीकृ. 2 एकत्र परीक्ष् 1 A, संमृश् 10. **-Comparative, a.** आनुपातिक (की f.), तुलनया निर्णीत, उपमाजन्य ; oft. by अपेक्षया in comp. **-ly, adv.** 'as c. ed with' तुलनया, औपम्येन, उपमानेन, अपेक्षया ; 'I like mango as c. ed with a Jambu fruit' जंबुफलात्-जंबुफलापेक्षया आम्रं मेऽधिकतरं रोचते; 'the merits of Rāma c.' अन्यापेक्षया रामस्य गुणाः. **-Comparison, s.** तुला, तुलना, उपमा-मानं, सादृश्यं, औपम्यं, 'without c.' अतुल, अनुपम; 'standard of c.' उपमानं; 'subject of c.' उपमेयं.

Compartment, s. शाला, कोष्ठः, कक्षः-क्षा. 2 छेदः, भागः, अंशः.

Compass, s. विषयः, गोचरः; 'within the c. of the eye' नयनगोचरस्थ. 2 मंडलं, परिधिः, परिणाहः, विस्तारः, परिमाणं, पर्यंतः. 3 परिमितता, अनतिक्रमः. 4 दिङ्निर्णययंत्रं. **-v. t.** परिगम् 1 P, परि-इ 2 P, परिवेष्ट् 1 A, or c., परिवृ 5 U. 2 अधिगम् 1 P, लभ् 1 A, *See* **Get.** 3 घट् c. (घटयति), साध् 5 P or c., संपद् c., निष्पद् c.

Compassion, s. दया, अनुकंपा, कृपा, घृणा, करुणा, अनुक्रोशः ; 'feel or have c. for' अनुकंप् 1 A, अभ्युपपद् 4 A, दयां कृ

or दय् c. (loc.), कृ 1 A, (gen.). -ate, *a.* सदय, करुणार्द्र, सानुकंप, सानुक्रोश, कृपालु, दयालु, सकरुण, कृपाशील. -ately, *adv.* सदयं, सानुकंपं, कृपया.

Compaternity, *s.* धर्मपितृत्वं.

Compatible, *a.* अनुगुण, अनुरूप, अविरुद्ध, उपयुक्त; *See* **Consistent.** -**Compatibility,** *s.* अविरोधः, योग्यता, अनुरूपता, अविसंवादः.

Compatriot, *s.* स्वदेशजः, एकदेशनिवासिन् *m.*

Compeer, *s.* वयस्यः, समानपदस्थः.

Compel, *v. t.* Ex. by causal, of verbs with बलात्, बलेन, or एव; 'I shall c. you to go' त्वां गमयिष्याम्येव or बलात् गमयिष्यामि; 'c. s payment' बलात् दापयति &c.; 'c.s me to ask' बलादनिच्छंतमपि मां प्रश्नकर्मणि नियोजयति (Ka. 134); sometimes ex. by अवश्यं, with pot. pass. part; 'you will be c. ed to stay here' त्वयात्रावश्यं स्थातव्यं; or by प्रेर् c., प्रवृत् c. -**Compulsory,** *a.* अवश्य-क, 'it is not c. on you to go' गमनं न तेऽवश्यकं. 2 बलवत्, बलिन्. -ly, *adv.* बलात्, अवश्यं, बलेन, अनिच्छत् *a.* (ती-न्ती *f.*) -**Compulsion,** *s.* बलात्कारः, प्रसभं, साहसं, बलं; 'by c.' बलात्, बलेन, प्रसभं, प्रसह्य, हठात्.

Compend, Compendium, *s.* संक्षेपः, संग्रहः, संहारः, सारः. -**Compendious,** *a.* संक्षिप्त, संगृहीत, अविस्तीर्ण, परिमित, सारभूत. -ly, *adv.* संक्षेपेण, संक्षेपतः, समासतः, अविस्तरेण. -ness, *s.* संक्षेपः, अविस्तरः.

Compensate, *v. t.* परितुष् c., निष्कृतिं दा 3 U, प्रत्युपकृ 8 U, (of persons); अपाकृ, शुध् c., निस्तृ c. -ion, *s.* प्रतिफलं, निष्कृति *f.*, निस्तारः, पारितोषिकं. -ive, *a.* क्षतिहानि-पूरक.

Compete, *v. i.* स्पर्ध् 1 A, संघृष् 1 P, विजि desid. (जिगीषते); oft. ex. by अहमहमिका, अहमहमिकया प्रणाममालसाः (Ka. 81) 'c.-ing with one another to salute first.' -ence, -ency, *s.* योग्यता, सामर्थ्यं, शक्ति *f.*, औचित्यं, कार्यक्षमता. 2 कृच्छ्रोचितं द्रव्यं; 'bare c.' ग्रासाच्छादनमात्रं. -ent, *a.* योग्य, उचित, समर्थ, शक्त, क्षम, पर्याप्त, कार्यक्षम, कार्यनिर्वाहक्षम. 2 परिमित, अनधिक. -ition, *s.* स्पर्धा, अहमहमिका, संघर्षः, विजिगीषा. -itor, *s.* प्रतिस्पर्धिन् *m.*, प्रत्यर्थिन् *m.*, प्रतिपक्षः, प्रतियोगिन् *m.*

Compile, *v. t.* संकल् 1 P, 10. (कलयति), सं-समा-हृ 1 P, आलोड् 10, संग्रह् 6 P. उद्धृत्य समाहृ. -ation, *s.* संकलनं, संग्रहः, सारः. -er, *s.* समाहर्तृ *m.*, संग्रहीतृ *m.*, व्यासः, संकलयितृ *m.*

Complacence, -cy, *s.* प्रसादः, संतोषः, प्रीति *f.* 2 सौजन्यं, अनुवृत्ति *f.*, दाक्षिण्यं. -**Complacent,** *a.* प्रसन्न, सुसंतुष्ट, सुप्रीत. 2 सुशील, दक्षिण. -ly, *adv.* प्रसादेन, प्रीत्या, सानंदं.

Complain, *v. i.* Ex. by verbs of 'telling' gen. with सशोकं, सविलापं; आ-अधि-क्षिप् 6 P; 'c. ed of her brother's rudeness to her father' भ्रातुरविनयमधिकृत्य पित्रे कथयत्, or भ्रातुरविनयाचरणं पित्रे न्यवेदयत्; 'c. ed to me of partiality' पक्षपातमधिकृत्य मां सविलापं विज्ञापयामास; 'how can I do what you c. of' यत्त्वं मय्यारोपयसि तत्कथमहं कुर्यां. 2 विलप् 1 P, क्रुश् 1 P, परिदेव् 1 A, आक्रंद् 1 P, आक्रुश् 1 P. 3 अभियुज् 7 A; 10, राजकुले निविद् c. (in law). 4 पीड् pass., अनुभू 1 P; 'has been c. ing of ill-health' आमयपीडितः. -ant, *s.* अभियोक्तृ *m.*, अर्थिन् *m.*, अभियोगिन् *m.*, वादिन् *m.*, पिशुनः. -er, *s.* परिदेवकः, विज्ञापिन् *m.* -**Complaint,** *s.* अभियोगः. 2 विज्ञापना (सविलापा); दुःखनिवेदनं, विलपनं, परिदेवनं; 'breathed out this doleful c.' इमानि परिदेविताक्षराणि सकरुणमुदीरयामास. 3 व्याधिः, पीडा, रोगः, आमयः. 4 विलपनविषयः.

Complaisance, *s.* दाक्षिण्यं, अनुवृत्ति *f.* अनुनयः, प्रश्रयः, अनुरोधः. -**Complaisant,** *a.* दाक्षिण, अनुनयिन्, अनुरोधिन्, अनुकूल, सप्रश्रय. -ly, *adv.* सानुनयं, सानुरोधं.

Complement, *s.* पूरणं, परिपूरकं. 2 कोटि *f.* 3 पूर्णता, सामग्र्यं.

Complete, *v. t.* समाप् c., संपद् c., साध् c., अवसो c. (साधयति), निर्वह् c., संधृ c. (पूरयति) or संपूर् 10, निर्वृत् c. -*a.* संपूर्ण, समाप्त, अवसित, सिद्ध, संपन्न, निर्वृत्त. 2 संपूर्ण, निखिल, अखिल, समस्त, समग्र, अशेष, अन्यून. 3 पक्व, परिणत; 'c. army' सांगबलं. -ion, *s.* समापनं, निर्वर्तनं, संपादनं. 2 सिद्धि *f.*, समाप्ति *f.*, निर्वृत्ति *f.* 3 परिणामः, परिपाकः. 4 पूरणं, परिपूरकं. -ly, *adv.* संपूर्णं; निःशेषं, पर्याप्तं, निरवशेषं, अशेषतः, सर्वथा. 2 आमूलं, कार्त्स्न्येन. -ness, *s.* संपूर्णता, निःशेषता.

Complex, *a.* संकीर्ण, मिश्रित, विषम, संमिश्र, मिश्र, संकुल. 2 नानार्थक, असरल, बह्वर्थ -ity, *s.* संकरः, मिश्रता, संकुलता.

Complexion, *s.* वर्णः, मुखरागः; 'of a pale c.' विवर्ण *a.*, पांडुवदन *a.* 2 आकारः, स्वरूपं. 3 प्रकृति *f.*, शरीरभावः. -al, *a.* प्रकृतिसंबंधिन्.

Complicate, *v. t.* संमिश्र् 10, संकीर्ण-संकुल -*a.* कृ 8 U, प्र-सं-कॄ 6 P, संकरी-संकुली-

कृ. -ion, s. संकुलीकरणं, संकीर्णता, संमिश्रता.

Complice, s. पापसहायः. **-ity,** s. पापसहायता, सहकारिता.

Compliment, s. अभिनंदनवचस् n., नमस्कारः; 'presents c. s' अभिनंदय प्रवीति; 'give my c. s to Chyavana' च्यवनाय मां प्रणिपातय (V. 5), मद्वचो नमस्कारो वाच्यः; श्वश्रूजनं सर्वं विज्ञापय प्रापितमत्प्रणामः (R. xiv 60). **2** प्रश्रयवाच् f., चाटूक्ति f., प्रशंसा, श्लाघा, प्रशंसोक्ति f.; 'high c.' उच्चैर्वादः; स्तुति f. **-v. t.** *See* **Praise 2** मधुरगिरा-चाटूक्त्या सांत्व् 10. **-ary,** a. उपचार in comp., 'c. saying' उपचारपदं; प्रियवादिन्, स्तुतिमय (यी f.); 'c. present' उपायनं. **-er,** s. प्रियवादिन् m., चाटुकारः.

Complot, v. i. गूढं मंत्र् 10 A, कूटसंविदं कृ 8 U. **-s.** गूढ-कु-मंत्रणा, कूटसाहित्यं. **-ter,** s. कूटसहाय.

Comply, v. i. अनुविधा 3 U, अनुरुध् 4 A, अनुवृत् 1 A. **2** अनु-सं-मन् 4 A, अनुज्ञा 9 U, स्वीकृ 8 U, प्रति-परि-ग्रह् 9 P, प्रतीष् 6 P, अभ्युपगम् 1 P; क्रियतामस्याः प्रणयपरिग्रहः (Ka. 145) 'c. with her request.' **-ance,** s. अनुवृत्ति f., अनुविधायित्वं, अनुरोधः, अनुसारः. **2** स्वीकारः, संमति f., अभ्युपगमः, परिग्रहः; 'in c. with your orders' त्वदाज्ञासमनुरोधात्-नुसारेण. **-ant,** a. अनुविधायिन्, अनुवृत्ति-कुशल-शील, अनुरोधिन्, वचने स्थित. **-er,** s. अनुरोधिन् m., प्रतिग्रहिन् m.

Component, a. or s. घटक, साधक, रचक; 'c. part' घटकावयवः, अंगं, भागः, साधनं.

Comport, v. i. **Behave,** q. v. **2** युज्-उपपद्-pass. **-able,** a. योग्य, उचित. **-ment,** s. आचारः, व्यवहारः, चेष्टितं.

Compose, v. t. (of books &c.) ग्रथ् 1 P, विरच् 10, बंध् 9 P, निबंध्, संग्रंथ् 9 P. **2** विन्यस् 4 P, संधा 3 U, संक्लृप् c., संविधा, निर्मा 3 A. **3** घट् c. (घटयति), निर्मा, क्लृप् c.; or gen. ex. by आत्मक, रूप, मय (यी f.) in comp.: 'the body c. ed of 5 elements' पंचभिर्निर्मितो देहः, पंचभूतात्मको देहः. **4** (Calm) स्थिरीकृ 8 U, शम् c. (शमयति), प्रसद् c., संस्तंभ् c., पर्यवस्था c. (स्थापयति); 'does not yet c. (collect) himself' वाद्यापि पर्यवस्थापयत्यात्मानं (U. 3). **5** (a dispute &c.) संधा 3 U, प्रशम् c. (प्रशमयसि विवादं S. 5). **-ed,** a. शांत, प्रसन्न, अव्याकुल, अनुद्विग्न, स्थिरीकृत, समाहित. **2** विरचित, निर्मित, निबद्ध; 'c. in verse, or music' श्लोक-स्वर-बद्ध; 'c. of' घटित, आत्मक-(त्मिका f.), रूप in comp. **-edly,** adv. असंभ्रमं, प्रशांतचेतसा, निर्वेगं. **-er,** s. रचकः, प्रणेतृ m., निर्बंधृ m. **-ition,** s. रचना, ग्रथनं, निर्माणं, निबंधनं. **2** विन्यासः, संधानं, प्रशमनं. **3** समसनं, मिश्रणं, संयोगः, संधिः, संघातः. **4** ग्रंथः, प्रबंधः, निबंधः. **-ure,** s. स्थैर्यं, शमः, प्रसादः, असंभ्रमः, अक्षोभः. **2** संधानं, संयोगः, मिश्रणं, निर्माणं.

Compotation, s. सहपानं, संपीति f.

Compound, v. t. संयुज् 10, संमिश्र् 10, संधा 3 U, समस् 4 P, संश्लिष् c. **2** (a dispute) संधा, समाधा c., प्रशम् c. (शमयति). **-v. i.** ऋणशोधनेन आनृण्यं गम् 1 P; 'was glad to c. for his escape with the loss of it' तन्नाशेनापि मुक्तिरभवदिति हृष्टो बभूव. **-a., -ed,** a. संयुक्त, यौगिक (की f.), संसृष्ट, संमिश्र, सामासिक, साधित; 'c. word' समासः. **-s.** मिश्रणं, संकरः; मिश्रितद्रव्यं, योगः. **2** परिसरभूमि f., प्रांगणं (नं). **-er,** s. मिश्रणकृत्-समाधातृ m.; 'c. of medicines' औषधयोगविद् m.

Comprehend, v. t. बुध् 1 P, विद् 2 P, ज्ञा 9 U, ग्रह् 9 P, परिग्रह्, उपलभ् 1 A, अवगम् 1 P, ऊह् 1 A; विभू c., अवधृ 10. **2** व्याप् 5 P, अंतर्गण् 10, अंतर्भू c., परिग्रह् 9 P, आकल् 10, समाविश् c. **-Comprehensible,** a. ग्राह्य, वेद्य, अवधारणीय, विभाव्य, धीगम्य; 'easily c.' सुबोध; 'not c.' दुर्बोध, दुर्ग्रह, दुर्गम, दुर्ज्ञेय. **-Comprehension,** s. ग्रहणं, बोधः. **2** धी f., मति f., बुद्धि f., अवधारणा, मेधा; 'power of c.' ग्रहणसामर्थ्यं, आकलनशक्ति f. **3** प्रतिसंहारः, व्याप्ति f., समावेशः, अंतर्भावः. **-Comprehensive,** a. व्यापक, बहुविस्तीर्ण, व्यापिन्, बहुग्रह. **2** साक्षेपिक (की f.). **-ly,** adv. समासतः, संक्षेपेण. **2** व्यापकत्वेन. **-ness,** s. व्यापकत्वं. **2** संक्षेपः, समस्तता.

Compress, v. t. संवृ 5 U, संकुच् 1 P, संवृष् 2 P, संपीड् 10, संह् 1 P. **-ible,** a. संकोचनीय. **-ibility,** s. संकोचक्षमता, संहरणीयता. **-ion,** s. संकोचः-चनं, संहति f., संपीडनं; संवरणं.

Comprise, v. t. व्याप् 5 P, अंतर्गण् 10, परिग्रह् 9 P, समाविश् c., अंतर्भू c.; 'to be c. ed in' अंतर्गम् 1 P, अंतर्भू 1 P, or by आत्मक, गर्भ, in comp.

Comprobation, s. प्रमाणं, साक्ष्यं, संमति f.

Compromise, v. t. आपद् 10. **2** संशये पत् c., संशयस्थ a. कृ 8 U. **-s.** आपोषः-षणं. **2** मध्यस्थावलंबननियमः.

Comprovincial, a. एकदेशीय, एकदेशज.

Comptrol, v. t. अधिष्ठा 1 P, पर्यव-ईक्ष् 1 A. **-ler,** s. कार्याधिकृतः, पर्यवेक्षकः, कार्यग्रह m.

Compulsion, -sory, *See* under **Compel.**

Compunction, s. अनुशयः, अनुतापः, पश्चात्तापः. **-Compunctious,** a. अनुशयार्त, अनुतापिन्.

Compute, *v. t.* गण् 10, सं-परि-सं-ख्या 2 P, संकल् 10. **-ation,** *s.* गणनं-ना, संकलनं. **-er,** *s.* गणकः.

Comrade, *See* **Companion.**

Con, *v. t.* अधी 2 A, अभ्यस् 4 U.

Concatenate, *v. t.* (अविच्छेदं) संयुज् 10, संश्लिष् c., अनुबंध् 9 P, संधा 3 U. **-ion,** *s.* अविच्छेदसंयोगः, निरंतरः संश्लेषः, अनुबंधः. **2** माला, परंपरा, श्रेणी, पंक्ति *f.*

Concave, *a.* पुटाकार, उत्तान, उदराकार. **-ity,** *s.* उत्तानता, पुटः, गर्भः.

Conceal, *v. t.* गुह् 1 U, प्रच्छद् 10, अपवृ 5 U or c, अंतर्धा 3 U; पिधा 3 U, संवृ, नि-अप-ह्नु 2 A (feelings &c.); गुप् 1 P or 10; 'c. oneself' 'to be c. ed' अंतर्-हृ 2 P; 'c. ing the body (oneself) behind a bush' विटपांतरितविग्रहः (Ka. 152); ली 4 A (मातुर्निलीयते कृष्णः S. K). **-ed,** *a.* गूढ, प्रच्छन्न, निभृत, गुप्त, निलीन. **-ment,** *s.* गूहनं, प्रच्छादनं, नि-अप-ह्नवः, गोपनं, संवरणं; 'in c.' निभृतं, रहः, गुप्तं, छन्नं.

Concede, *v. t.* अनुमन् 4 A, प्रदा 3 U, अनुज्ञा 9 U, वितॄ 1 P; 'c. ed the point to him' तस्याभिप्रेतमन्वमन्यत. **2** अंगीकृ 8 U, अभ्युपगम् 1 P, प्रतिपद् 4 A. **-Concession,** *s.* प्रदानं, वितरणं, त्यागः. **2** क्षमा. **3** अंगीकारः, प्रतिपत्ति *f.*, अभ्युपगमः.

Conceive, *v. i.* गर्भं धृ 1 P, 10 or आधा 3 U, गर्भवती-आपन्नसत्त्वा-ससत्त्वा-अंतर्वत्नी भू 1 P. **-***v. t.* विभू c., बुध् 1 P, अवधृ 10, अवगम् 1 P, ग्रह् 9 P, आलोच् 10, ज्ञा 9 U. **2** मन् 4 A, चिंत् 10, ध्यै 1 A. **3** संभू c., क्लृप् c. (नरपतौ भूधनविक्रयं को नाम संभावयेत् Mu. 5). **4** धृ, वह् 1 P; *See* **Bear**; 'I c. no hatred against you' त्वयि मे द्वेषबुद्धिर्नास्ति, न त्वामसूयामि. **-Conception,** *s.* गर्भाधानं, गर्भधारणं. **2** विभावना, बोधः, ग्रहणं, अवधारणं. **3** विचारः, कल्पना, भावना, बुद्धि *f.*, मति *f.*, संकल्पः. **-Conceit,** *s.* अभिमानः, अवलेपः, दर्पः, अहंकारः, गर्वः; 'self-c.' स्वाभिमानः. **2** कल्पना, भावना, चिंता, विचारः. **3** मति *f.*, बुद्धि *f.*, मतं. **-ed,** *a.* दृप्त, अवलिप्त, अभिमानिन्, उद्धत, आत्मसंमानिन्, सगर्व; 'c. of learning' पंडितंमन्यः. **-edly,** *adv.* साभिमानं, सगर्वं. **-edness,** *s.* मानिता, अहंकारः, सगर्वता.

Concentre, *v. t.* एकीकृ 8 U, See below; 'c. ed all in self' आत्मपरायणः, आत्मन्येव निविष्टचेतोवृत्तिः.

Concentrate, *v. t.* समाहृ 1 P, समुपचि 5 U, एकीकृ 8 U. **2** समाधा 3 U (as mind); अनन्यमनस्क-एकाग्र-*a.* भू; 'my affections are c. ed in her' सा मे स्नेहस्यैकायनीभूता (M. 2). **-ed,** *a.* एकतान, अनन्यवृत्ति, एकाग्र, एकायन, एकसर्ग, एकाग्रच, एकायनगत. **-ion,** *s.* एकीकरणं, एकत्र-समाहरणं. **2** एकाग्रता, समाधि, अनन्यमनस्कता.

Concentric,-cal, *a.* एक-समान-केंद्र.

Concern,-ment, *s.* अर्थः, व्यापारः, विषयः, कार्यं, संबंधः. **2** चिंता, उद्वेगः, औत्सुक्यं. **3** गौरवं, गुरुता, माहात्म्यं. **4** अवेक्षा, प्रणयः, अनुरागः, मनोयोगः, मनोभिनिवेशः. **5** चर्चा, व्यापारः, विचारः. **-***v. t.* संबंध् 9 P, उद्दिश् 6 P, आश्रि 1 U; 'this does not c. you' नायं तव व्यापारः. **2** अवेक्ष् 1 A. **3** Afflict, q. v. **4** (Oneself about) व्यापृ 6 A, आत्मानं व्यापृ c., व्यापृत *a.* भू, चर्चां कृ; 'I am not c. ed in the least in this business' अनेन कर्मणा न मे कोपि संबंधः. **-ing,** *prep.* संबंधिन् -विषय in comp.; उद्दिश्य, अधिकृत्य, आश्रित्य.

Concert, *s.* एकतानः-लः, संगीतं; 'c. hall' संगीतशाला. **2** संप्रधारणा, सन्मंत्रणं, कार्यविमर्शः, संवादः. **3** सहकारिता, संभूयकारित्वं, चित्तैक्यं, एकभावः. **-***v. t.* संमंत्र् 10 A, संप्रधृ 10, कार्याणि चिंत् 10 or विमृश् 6 P, संवद् 1 P. **2** संभूय-एकत्र-कृ 8 U. **3** घट् c. (घटयति), कल्प् c., चिंत् 10; 'well c. ed plan' सुघटितः-सुचिंतितः-प्रयोगः.

Conch, *s.* शंखः, कंबुः, दरं.

Conciliate, *v. t* अनुरंज् c., आराध् 10, प्रसद् c., तुष् c, लल् 10, सांत्व् 10. **2** संधा 3 U, अनुनी 1 P. **-ion,** *s.* अनुरंजनं, सांत्वनं, प्रसादनं. **2** सामन् *n*, संधानं. **-or,** *s.* अनुरंजकः. **2** संधानकर्तृ *m.*, मध्यस्थः. **-ory,** *a.* आराधक, सामन् in comp.; सामोपचाराः 'c. means'.

Concise, *a.* संक्षिप्त, संहृत, सामासिक (की *f.*). **-ly,** *adv.* संक्षेपेण, संक्षेपतः, अविस्तरेण, समासतः; 'a c. worded message' लघुसंदेशपदा सरस्वती (R. viii. 77). **-ness,** *s.* संक्षिप्तता, संहारः, अविस्तरः. **-Concision,** *s.* कर्तनं, छेदनं, उच्छेदः.

Concitation, *s.* उत्तेजनं, प्रोत्साहनं, उत्थापनं.

Conclave, *s.* समाजः, सभा, परिषद् *f.* **2** गूढसभा-समाजः. **3** कक्षांतरं.

Conclude, *v. t.* समाप् c., निर्वृत् c., अवसो 4 P, निष्पद् c., संपद् c., साध् c., संपूर् 10. **2** अनुमा 3 A, विभू c., ऊह् 1 A, तर्क् 10. **3** निर्णी 1 P, निश्चि 5 U, अवधृ 10, व्यवसो 4 P; 'c. a treaty' संधिं कृ 8 U or विधा 3 U. **-***v. i.* विरम् 1 P, निवृत् 1 A; प्र-उपशम् 4 P; 'when he had c. ed' वचस्यवसिते तस्य. **-Conclusion,** *s.* समाप्ति *f.*, निष्पादनं, सिद्धि *f.*, निष्पत्ति *f.*, निवृत्ति *f.* **2** अवसानं, अंतः, परिणामः, उपसंहारः. **3** अनुमानं, ऊहनं, अनुमिति *f.* **4** निर्णयः, अवधारणं, फलं, उत्तरं. **5** सिद्धांतः, राद्धांतः, उत्तर-

पक्षः, निगमनं (in logic). **-Conclusive,** *a.* अखंड्य, अनिरस्य, निरुत्तर, समर्थ. 2 निर्णायक, संशयच्छेदिन्, निश्चायक. **-ly,** *adv.* सनिश्चयं, निश्चितं, संशयच्छेदितया.

Concoct, *v. t.* पच् क्वथ् 1 P, तप् c. 2 चिंत् 10, घट् c. (घटयति), प्रकॢप् c., निरूप् 10. **-ion,** *s.* क्वाथः. 2 पाकः, पाचनं. **-ive,** *a.* पाचक.

Concomitant, *a.* आनुषंगिक (की *f.*), समवायिन्, समेत, समन्वित; सहवर्तिन्, सहकारिन्. **-s.** सहचारिन् *m.*, सहवर्तिन् *m.*, संगिन् *m.* **-ly,** *adv.* समवेतं, सहितं, सह, संभूय. **-Concomitance,** *s.* संयोगः, समन्वयः, अनुषंगः, समवायः.

Concord, *s.* ऐक्यं, एकता; चित्तैक्यं, अविसंवादः, अविप्रतिपत्ति *f.*, अविरोधः; 'c. of hearts' ऐक्यं हृदययोः, ...सता. 2 प्रीति *f.*, प्रणयः, संधिः. 3 ...यः, संविद् *f.*, नियम. 4 अनुषंगः, अन्वयः, समन्वयः. 5 ... स्वरैकता. **-ance,** *s.* एकता, सादृश्य, ऐक्यं. **-ant,** *a.* अनुरूप, अनुगुण, सदृश (शी *f.*), अविरुद्ध, संवादिन्.

Concourse, *s.* संधिः, संगमः. 2 (of people) (जन-) समूहः, संघातः, निवहः, ओघः, गणः.

Concrement, *s.* पिंडः, राशिः, घनता, संहति *f.*, संघातः.

Concrete, *v. t.* राशीकृ 8 U, पिंडीकृ, एकीकृ, घनीकृ, संहन् 2 P. **-***v. i.* राशिभू 1 P, पिंडीभू, घनीभू, संहन् pass. **-***s.* पिंडः, ओघः, घनचयः. 2 घनद्रव्यं, श्यानद्रव्यं. **-***a.* घन, राशीभूत, संहत, श्यान, पिंडीभूत. 2 अविविक्त, अकेवल, समवेत, अन्वित. **-ion,** *s.* घनीकरणं; संहति *f.*, संघातः, 2 पिंडः, लोष्टः, संहतद्रव्यं.

Concubine, *s.* उपपत्नी, उपस्त्री, गणिका, वारस्त्री, वेश्या ; 'c. shut up' अवरोधस्त्री. **-age,** *s.* उपस्त्रीगमनं, वेश्यासेवा.

Concupiscence, *s.* कामः, अभिलाषः, रताभिरुचि *f.* **-Concupiscient,** *a.* कामुक, कामिन्, रतार्थिन्.

Concur, *v. i.* एकत्र मिल् 6 P, संगम् 1 A, संभू 1 P, संपत् 1 P, समागम् 1 P. 2 संभूय-एकीभूय-कृ 8 U, 3 संमन् 4 A, तथा मन्; अभ्युपगम्, एकचित्तीभू; *See* **Agree.** **-rence,** *s.* सं-अनु-मति *f.*, संमतं, इच्छा. 2 मतैक्यं, एकचित्तता. **-rent,** *a.* एकचित्त, संप्रतिपन्न, संवादिन्. 2 अनुषंगिन्, संभूय-सह-कारिन्. **-rently,** *adv.* सम्मतिपूर्वं, अनुमत्या. 2 सममेव, युगपत्.

Concussion, *s.* संघट्टः, विकंपः, विधुवनं, संक्षोभः.

Condemn, *v. t.* Censure, q. v. 2 दंड् 10, दंडं आदिश् 6 P or कृ 8 U. 'c. to death' वधदंडमादिश् ; 'he was c.-ed to be hanged' शूलमारोप्यतामममायेति दंडं आदिष्टः. 3 अपराधिन् *a.* स्था c. (स्थापयति), अपराधं निर्णी 1 P; 'c. to pay' दा c. (दापयति). **-ation,** *s.* दंडनं, दंडाज्ञा. 2 अपराधनिर्णयः. 3 निंदा, गर्हा, दूषणं. **-atory,** *a.* निंदक, अपवादक. **-er,** *s.* दंडप्रणेतृ *m.* निंदकः.

Condense, *v. t.* संहन् 2 P, घनीकृ 8 U, सांद्रीकृ, श्यै c. 2 संक्षिप् 6 P. **-***v. i.* सांद्री-घनी-भू, संहन् pass., श्यै 1 A. **-***a.* **-ed,** *a.* घन, सांद्र, निबिड, श्यान; संक्षिप्त. 2 स्थूल, अविरल. **-ation,** *s.* घनीकरणं. **-ity,** *s.* घनता, निबिडता, &c.

Condescend, *v. i.* प्रसद् 1 P, अर्ह् 1 P, (followed by inf.) ; *See* **Please** ; 'the king c.-ed to speak with his servant' प्रसन्नो भूत्वा, दाक्षिण्यतया, गौरव-अभिमानं-अपास्य, भृत्येन सहाभाषत ; 'c. to look at me' मयि दृष्टिप्रसादं ... . 2 ... अनु..., अनुज्ञा 9 U. ... *a.* प्रसादाभिमुख (खी *f.*), प्रसन्न, अस्तगर्व, त्यक्तगौरव. **-ingly,** *adv.* अगर्वं, प्रसन्नतया, नम्रतया. **-Condescension,** *s.* प्रसादः, दाक्षिण्यं, दर्पत्यागः, गौरवत्यागः, नम्रता.

Condign, *a.* यथार्ह, अनुरूप, समुचित, योग्य. **-ly,** *adv.* यथार्हं, यथोचितं. **-ness,** *s.* योग्यता, औचित्यं.

Condiment, *s.* व्यंजनं, उपस्करः.

Condisciple, *s.* सतीर्थः (-र्थ्यः), एकगुरुः.

Condition, *s.* दशा, अवस्था, भावः. स्थिति *f.*, वृत्ति *f.*, गति *f.*; 'in this c.' एवंविध *a.*, एवंभूत *a.*; oft. ex. by त्व & ता affixed; दरिद्रता, दुर्गतत्वं, &c. 2 समयः, नियमः, प्रतिज्ञा, अभिसंधिः; संकेतः; 'on this c.' अनेन समयेन. 3 अर्थः, आस्पदं, पदं, अधिकारः, भावः. 4 गुणः, उपाधिः, विशेषणं, प्रकृति *f.* **-al,** *a.* समययुक्त, सोपाधिक (की *f.*), सनियम, नियत; संकेतार्थ. **-ally,** *adv.* समयपूर्वकं, सप्रतिज्ञं, समयपुरःसरं. **-ed,** *a.* स्थित, वर्तिन्, स्थ in comp.; 'well c.' सुस्थित, सुस्थ.

Condole, *v. i.* समदुःख *a.* भू 1 P, (अन्वं) अनुशुच् 1 P, शोकार्तं समदुःखेन सांत्व् 10. **-ence,** *s.* समदुःखता, अनुशोचनं, शोकः, संपरिदेवनं **-er,** *s.* समदुःखभागिन् *m.*

Condone, *v. t.* क्षम् 1 A, प्रमुच् c., प्रमुच् 2 P. **-ation,** *s.* क्षमा, अपराधक्षमा, वर्जनं.

Conduce, *v. i.* (to) आवह् 1 P (... राज्यं न मे सौख्यमावहति ... 1. 1), भू with dat., कॢप् 1 A, संवद् 1 A (dat.). 2 ... c., संवद् c., ... c. **-ive,** *a.* आवह, कर (री *f.*) ... in comp.; 'c. to happiness' सुखावह, ... कर, &c.

Conduct, *v. t.* नी 1 P, प्राप् c. (... मां प्रापय पत्युरंतिकं K ...) गम् c. (गमयति), वह् 1 P. 2 नियम् ..., निर्वह् c., प्रवृत् c., पालि. 3 (oneself) वृत् 1 A.

व्यवह् 1 P, आचर् 1 P, *See* **Act;** 'c. oneself properly' सदाचारेण वृत्, सदाचारं प्रतिपद् 4 A; 'well c. ed' साधुवृत्त, सदाचार. 4 परि-अनु-चर् 1 P, अनुया 2 P, मार्गं दृश् c. or आदिश् 6 P. **-s.** निर्वाहणं, निर्वाहः, प्रणयनं. 2 वृत्ति *f*., वृत्तं, आचारः, व्यवहारः, कर्मन् *n*., चरितं, चेष्टितं, आचरणं. 3 परिचरः, मार्गदर्शकः. **-or,** *s.* नायकः, अग्रगः, नेतृ *m*., अग्रणीः, (of heat &c.) प्रवाहकः. 2 निर्वाहकः, प्रणेतृ *m*.

Conduit, *s.* प्रणाली, जलनिर्गमः. 2 कुल्या.

Cone, *s.* सूचि-ची *f*., शिखा. 2 शंकुः. **-Conic, -Conical,** *a.* सूच्याकार, शंकाकृति.

Confabulate, *See* **Converse.**

Confect, *v. t.* उपस्कृ 8 U, स्वादु *a.* कृ. **-ion,** *s.* उपस्करः, मिष्टान्नं, मोदकः. **-ionery,** *s.* मोदकविक्रयस्थानं, मोदकक्रियास्थानं **-ioner,** *s.* आपूपिकः, भक्ष्यंकारः.

Confederate, *v. t.* संधा 3 U, संयुज् 7 U, 10, एकत्र कृ 8 U. **-v. i.** संबन्ध् 1 A, संयुज् pass., संधिं कृ. **-a.** संधिबद्ध, सुश्लिष्ट, कृतसंधि, संयुक्त, संघातवत्. **-s.** सहायः, सहकारिन् *m*., सहयोगिन् *m*. **-ion,** *s.* संधानं; संयोजनं. **-Confederacy,** *s.* संधिः, साहित्यं, संघातः, संयोगः.

Confer, *v. t.* (upon) विसृज् 1 P (with loc.), प्रतिपद् c., दा 3 U, 1 P (with dat.); 'I shall c. upon you 100 grants of land' त्वां शासनशतेन योजयिष्यामि (P. 1. 1). 2 आवह् 1 P, दा, उत्पद् c. 3 Compare, q. v.; 'c. a favour' प्रसादं कृ 8 U, अनुग्रह् 9 P, 'c.-ing pleasure', सुखद, सुखावह. **-v. i.** संभाष् 1 A, संलप् 1 P. संवद् 1 P. 2 संमन्त्र् 10 A, संचिन्त् 10, विचर् c. **-ence,** *s.* संवादः; संकथा, संभाषणं. 2 मंत्रणं. 3 उपमानं. 4 मेलकः, समाजः. **-rer,** *s.* दातृ *m*., द or प्रद in comp.

Confess, *v. t.* स्वीकृ 8 U, अंगीकृ, प्रतिपद् 4 A, अभ्युपगम् 1 P, अभ्युप-इ 2 P. 2 विवृ 5 U, सूच् 10, प्रकाश् c., ख्या c. (ख्यापयति). 3 (आचार्याय-गुरवे) पापानि निविद् c. or कथ् 10. **-edly,** *adv.* असंशयं, व्यक्तं, प्रतिपत्तिपूर्वकं. **-ion,** *s.* अंगीकारः, संप्रतिपत्ति *f*., अभ्युपगमः, ग्रहणं. 2 ख्यापनं, प्रकाशनं. 3 पापनिवेदनं. **-or,** *s.* स्वीकर्तृ *m*.; ख्यापकः.

Confide, *v. i.* विश्वस् 2 P, प्रति-इ 2 P, श्रद्धा 3 U; 'she was made to c. in a false man' असत्यसंधे जने पदं कारिता (S. 4). **-v. t.** निक्षिप् 6 P, न्यस् 4 P (with loc.), सम्-ऋ c. (अर्पयति); 'have you kept the secret c. ed to you' अपि रक्ष्यते रहस्यनिक्षेपः (V. 2). **-ant,** *s.* विश्वास-विश्रंभ-भूमि *f*., सखि *m*., वयस्यः. 2 (of a woman) सखी, वयस्या, आलि-ली *f*. **-ence,** *s.* विश्वासः, विश्रंभः, प्रत्ययः; श्रद्धा. 2 निश्चयः, दृढप्रत्ययः, दृढज्ञानं, असंशयः; 'enter into c.' विश्वासं गम् 1 P or ग्रह् 1 P; 'raising of c.' विश्वासोत्पादनं; 'inspire with c.' विश्वासं नी 1 P; विश्वस् c.; 'take into c.' विश्रंभस्थाने मन् 4 A; 'self-c.' प्रगल्भता, प्रागल्भ्यं, धृष्टता, 'an object of c.' विश्वासभूमिः, विश्रंभस्थानं, -भाजनं. **-ent,** *a.* विश्वासिन्, विश्वासप्रतिपन्न-विश्वस्त, जातप्रत्यय, विश्रब्ध. 2 निश्चित, असंदेह, छिन्नसंशय; 'he is c. of success' जयं निश्चितं (ध्रुवं) मन्यते. 3 प्रगल्भ, धृष्ट, निर्विशंक, साहसिन्. **-ential,** *a.* विश्वस्त, विश्रब्ध; आप्त (आप्तजनः); 'c. talk' विश्रंभालापः; 'c. matter' विश्वासकार्यं. 2 गुप्त, अप्रकाश्य, संवरणीय. **-entially,** *adv.* विश्रब्धं; गुप्तं. **-ing,** *a.* विश्वासापन्न, विश्वासभाज्, विश्वस्त, जातप्रत्यय, विश्रब्ध, अविशंकमान, निःशंक. **-ingly,** *adv.* विश्रब्धं, सप्रत्ययं, निर्विशंकं, निःसंदेहं.

Configuration, *s.* आकारः, रूपं, मूर्ति *f*., विग्रहः, आकृति *f*.

Confine, *s.* सीमा, पर्यंतः, प्रांतः, समंतः, परिसरभूमि *f*. **-v. t.** पर्यंते-निकटे-स्था 1 P or वृत् 1 A. **-v. t.** नि-अव-रुध् 7 U, आसिध् 1 P, नि-सं-यम् 1 P, निग्रह् 9 P, बंध् 9 P, निर्बंध. 2 (oneself to) न व्यति-इ 2 P or उल्लंघ् 1 A, 10, नातिचर् 1 P. 3 संवृ 1 P, संकुच् 1 P. **-ed,** *a.* संयत, निरुद्ध, निबद्ध. 2 संकट, संकुचित; 'c. in the bowels' बद्धकोष्ठः; 'c. to bed' शयनग्रस्त; (of a woman) प्राप्तप्रसवकाला. **-ment,** *s.* संयमः, निरोधः, निग्रहः, बंधनं, कारागृहं; 'c. of bowels' विड्ग्रहः, आनाहः, मलावरोधः; 'c. of a woman' प्रसवकालः, प्रसवावस्था.

Confirm, *v. t.* दृढीकृ 8 U, दृढयति (D), संस्तंभ् c. 2 स्थिरीकृ, दृढप्रमाणं दा 3 U, प्रमाणीकृ, सुस्थिर-दृढ- *a.* कृ. **-ation,** *s.* दृढीकरणं, संस्तंभनं, स्थापनं, प्रमाणीकरणं. **-ed,** *a.* दृढीकृत, प्रमाणीकृत, स्थिरीकृत. 2 दृढ, स्थिर, रूढ, प्ररूढ; 'a c. fool' प्रतिविशिष्टमूर्खः, 'c. friendship' प्ररूढः संसर्गः, रूढसौहृदं.

Confiscate, *v. t.* सर्वस्वं अपहृ 1 P or आच्छिद् 7 P or दंड् 10, निःस्व *a.* कृ 8 U; 'let his property be c. ed' अस्य सर्वस्वहरणमादिश्यतां. **-ed,** *a.* राजापहृत, हृतसर्वस्व, निःस्वीकृत. **-ion,** *s.* सर्वस्वहरणं, सर्वस्वदंडः, सर्वस्वापहारः.

Conflagration, *s.* दाहः, ज्वलनं, दीपनं; 'forest c.' दावानलः दवः, दावः, अरण्यवह्निः *m*.

Conflict, *s.* विरोधः, (स्मृत्योर्विरोधः); द्वंद्वं, कलहः, वैरं; विप्रतिपत्ति *f*., विसंवादः. 2 युद्धं, संग्रामः, विग्रहः. 3 संघट्टः, समाघातः, अभिसंपातः. **-v. i.** युध् 4 A, विवद् 1 A, विग्रह् 9 P; 'mutually c. ing S'âstras

परस्परं विवदमानानां शास्त्राणां (H. 1); विप्रतिपद् 4 A, परस्परं विरुध् pass., विसंवद् 1 P. **-ing,** *a.* विप्रतिपन्न, विरुद्ध, परस्परविरोधिन्, विसंवादिन्.

Confluence, Conflux, *s.* संगमः, संभेदः, तोयव्यतिकरः, वेणि *f.* 2 संयोगः, समागमः, संमिलनं. 3 Concourse, q. v. **-Confluent,** *a.* संमेलक, संगवाहक.

Conform, *v. i.* (to) अनुवृत् 1 A, अनुचर् 1 P, अनुरुध् 4 A, प्रमाणीकृ 8 U, (इति गुरुजनचरितं प्रमाणीकुरु M. 3), अनुविधा 3 U. 2 युज् pass., सदृश-तुल्य *a.* भू, उपपद् 4 A, संवद् 1 P. **-v. t.** अनुरूप-सदृश *a.* (शी *f.*) कृ, समीकृ. **-able,** *a.* अनुरूप, सदृश, तुल्य, अनुगुण, समान, संवादिन्. 2 अनुविधायिन्, अनुरोधिन्, अनुकूल. 3 योग्य, उपपन्न. **-ably,** *adv.* अनुसारेण-सारतः, अनुरोधात्, अनुरूपं, यथा in comp. **-ity,** *s.* अनुरोधः, अनुवृत्ति *f.* 2 अनुरूपता, आनुगुण्यं, सादृश्यं, अनुसारः; 'in c. with' अनुसारेण, अनुरूपं, &c. 3 योग्यता, युक्तता. **-ist,** *s.* धर्मानुसारिन् *m.*, प्रवृत्तधर्मानुवर्तिन् *m.*

Confound, *v. t.* भ्रांत्या मन् 4 A; 'c. a falsehood with truth' सत्यमनृतमिति भ्रांत्या मन्यते; oft. by संदिह् 2 U; धूपैर्जालविनिःसृतैर्वलभयः संदिग्धपारावताः (V. 3) 'the pigeons c. ed with volumes of incense' &c.; *See* **Mistake.** 2 आकुलीकृ 8 U, मुह् c., वि-सं-क्षुभ् c., संभ्रम् c. (भ्रमयति). 3 संकॄ 6 P, विक्षिप् 6 P, संमिश्र् 10, संकुलीकृ. 4 विलुप् c., विनश् c.; 'c. by argument' निरुत्तरीकृ. **-ed,** *a.* मोहित, आकुल, संभ्रांत, विहस्त, व्यग्र, विक्षिप्त. 2 संकीर्ण, संमिश्रित, संकुल. 3 दैवोपहत; लुप्तज्ञान. **-er,** *s.* मोहकः, मोहनः. **-ing,** *a.* भ्रांतिजनक, संदेहोत्पादक, मोहिन्.

Confraternity, *s.* सौभ्रात्रं; भ्रातृत्वं, साहित्यं.

Confrere, *s. See* **Colleague.**

Confront, *v. t.* अभिमुखी-संमुखीकृ 8 U, अभिमुखयति (D.), समक्षं उपानी 1 P. 2 संमुखीभू 1 P, सं-अभि-मुखं स्था 1 P or गम् 1 P or वृत् 1 A. 3 **Compare,** q. v. **-ation,** *s.* संमुखस्थापनं; संमुखागमनं.

Confuse, *v. t.* वि-सं-भ्रम् c., आकुलीकृ 8 U, मुह् c. *See* **Confound;** 'to be c. ed' मुह् 4 P, आकुलीभू. **-ed,** *a.* मोहित, संभ्रांत, आकुल. 2 अस्पष्ट, अव्यक्त, क्रमहीन. **-edly,** *adv.* संकुलं, अक्रमेण, ससंभ्रमं. संकीर्णतया, अस्तव्यस्तं. 2 अस्पष्टं, संदिग्धतया. **-Confusion,** *s.* संभ्रमः, वैक्लव्यं, व्याकुलत्वं, व्यग्रता, विह्वलः, मोहः. 2 वैलक्ष्यं, व्रीडा, लज्जा. 3 संकरः, संक्षोभः, व्यतिकरः, संकुलं. 4 अक्रमः, अस्पष्टता, क्रमभंगः, अस्तव्यस्तता. 5 विनाशः, निग्रहः, लोपः.

Confute, *v. t.* खंड् 10, प्रत्यादिश् 6 P, निरस् 4 U, प्रत्याख्या 2 P, निरा-अपा-कृ 8 U; निरुत्तरीकृ (of persons). **-ation,** *s.* खंडनं, निराकरणं, निरसनं, प्रत्याख्यानं.

Conge, *s.* प्रणामः, नमस्कारः. 2 आमंत्रणं, अनुज्ञाग्रहणं, आपृच्छनं.

Congeal, *v. t.* घनीकृ 8 U, संहन् 2 P, श्यै c., पिंडीकृ; संचि 5 U. **-v. i.** घनीभू 1 P, श्यै 1 A, पिंडीभू, संहन् pass., शीतीभू. **-Congelation,** *s.* शीतीभावः, संहति *f.*, घनीभावः, घनीकरणं.

Congener, *s.* सजाति *m.*, सजातीयः.

Congenial, *a.* एकजातीय, सजाति. 2 समानशील, एकस्वभाव, सधर्मन्. 3 सुखावह, हितकर (री *f.*), अनुरूप, अनुगुण, अनुकूल, सदृश (शी *f.*); 'c. to health' आरोग्यावह, स्वास्थ्यकर. **-ity,** *s.* समानशीलता, सधर्मता, सजातित्वं. 2 आनुरूप्यं, आनुगुण्यं.

Congenital, *a.* सहज, सहजात.

Congenite, *a.* सहज, एककालोत्पन्न.

Conger, *s.* जलव्यालः.

Congeries, *s.* राशिः, संचयः, ओघः, पुंजः, स्तोमः

Congest, *v. t.* राशीकृ 8 U, संचि 5 U, पिंडीकृ, घनीकृ. **-ion,** *s.* (of blood) रक्तावष्टंभः, असृक्संचयः, रक्तसंचयः. 2 अतिबाहुल्योपचयः.

Conglobate, *a.* एकपिंडीभूत. **-v. t.** गोलीकृ 8 U, एकपिंडीकृ.

Conglomerate, *v. t.* राशीकृ 8 U, संचि 5 U, संभृ 3 U, एकपिंडीकृ, समाक्षिप् 6 P. **-ion,** *s.* समुपचयनं, एकीकरणं. 2 एकराशिः, एकपिंडः.

Conglutinate, *v. t.* संयुज् 10, संश्लिष् c., संधा 3 U; संरुह् c. (रोपयति) (of wounds). **-v. i.** pass. of roots above. **-ion,** *s.* संयोगः, संधिः, संधानं. 2 संरोपणं.

Congratulate, *v. t.* अभिनंद् 1 P or c., (तापसीभिरभिनंद्यमाना S. 4), gen. ex. by दिष्ट्या with वृध् 1 A or c., (विजयहेतवे दिष्ट्या वर्धयितुं Ka. 365); दिष्ट्या सुतमुखदर्शनेन आयुष्मान्वर्धते (S. 7) 'you are to be c. ed upon seeing your son's face', or 'I c. you upon seeing' &c. **-ion,** *s.* धन्यवादः, अभिनंदनं, दिष्ट्या वर्धनं. **-ory,** *a.* अभिनंदक, धन्यवादसूचक.

Congregate, *v. t.* समाचि 5 U, समाह् 1 P; *See* **Collect.** **-v. i.** संमिल् 6 P, संभू 1 P; *See* **Assemble.** **-ion,** *s.* सभा, परिषद् *f.*, संसद् *f.*, समाजः. 2 समवायः, निवहः, व्रजः, समाहारः, समुदायः. **-ional,** *a.* सामाजिक (की *f.*), सभ्य.

Congress, *s.* सभा, परिषद् *f.*, संसद् *f.*, मेलकः, समाजः, संसद् *f.* *n.* 2 संगमः, समागमः.

Congruous, *a.* योग्य, उचित, संगत, अविरुद्ध, अनुगुण, अनुरूप, सदृश (शी *f.*), संबद्ध. **-ly**, *adv.* युक्तं, अनुरूपं, संगतं. **-Congruity, Congruence**, *s.* संगतता, अनुरूपता, युक्तता, सादृश्यं; oft. ex. by क-क; 'what c. is there between this (youthful) age and this restraint of passions' क्वेदं वयः क्वायमिन्द्रियाणामुपशांतिः (Ka. 135)

Conjecture, *v. t.* तर्क् 10, अनुमा 3 A, 2 P, ऊह् 1 A, उत्प्रेक्ष् 1 A, (किमुत्प्रेक्षसे कुतस्त्योयमिति U. 4). **-s.** तर्कः, वितर्कः, ऊहः-हनं, अनुमानं; 'your c. is clear (you have rightly c. ed)' प्रसन्नः-उपपन्नः-ते तर्कः. **-al**, *a.* आनुमानिक (की *f.*). **-ally**, *adv.* अनुमानेन, सवितर्कं, अनुमानपूर्वकं.

Conjoin, *v. t.* संयुज् 7 U, 10, संश्लिष् c., संधा 3 U; 'c. ed in bonds of friendship' मित्रभावेन वर्तमानाः, परस्परानुरक्ताः. **-v. i.** संयुज्-संश्लिष्-संधा- pass. **-ed, Conjoint**, *a.* संहत, संयुक्त, संश्लिष्ट, संबद्ध. **-ly**, *adv.* सह, सहितं, संहत *a.*, संभूय.

Conjugal, *a.* वैवाहिक (की *f.*); oft. ex. by दंपती; 'c. love' दंपत्योः प्रेम; 'c. fidelity' अव्यभिचारः ; सतीत्वं, पातिव्रत्यं.

Conjugate, *v. t.* रूपाणि आख्या 2 P **-a.** संयुक्त. **-ion**, *s.* गणः ; '1st c.' भ्वादिगणः. 2 संयोगः.

Conjunct, *a.* संयुक्त, संश्लिष्ट; 'a c. consonant' संयोगः, योगः. **-ion**, *s.* संयोगः, योगः, संश्लेषः, संसर्गः, समागमः, संगमः ; संगः 2 समुच्चयः ; 'c. of planets' संगमः ; 'lunar c.' अमावास्या, अमा. **-ive**, *a.* संयुक्त, संश्लिष्ट, यौगिक (की *f.*). **-ure**, *s.* योगः, संयोगः, संधिः. 2 अवसरः, समयः, प्रस्तावः.

Conjure, *v. i.* मुह् c., मंत्रैर्वशं नी 1 P; मायां कृ 8 U, अभिचर् 1 P. 2 सशपथं आदिश् 6 P, शप् c.; 'I c. thee by my life (soul)' शापितासि मम जीवितेन (Mal. 8); अभ्यर्थ् 10 A, सशपथं संयुज् c. 3 (in mind) अनु-सं-स्मृ 1 P; चिंत् 10. **-v. t.** सशपथं ऐकमत्यं-कूटं-कृ 8 U, संशप् 1 U. **-ation**, *s.* माया, इंद्रजालं, कुहकः, मंत्रः. 2 शापनं. 3 सशपथः संकल्पः, संशपनं. **-er**, *s.* इंद्र-ऐंद्र-जालिकः, मायिन् *m.*, आहितुंडिकः, कुहककृत् *m.*, कुहकाजीवः.

Connate, *a.* सहज, एककालोत्पन्न, सहजात.

Connatural, *a.* सहज ; एकस्वभाव.

Connect, *v. t.* सं-अनु-बंध् 9 P. संयुज् 7 U, 10, संश्लिष् c., संधा 3 U, व्यतिबंध् 1 P, संनह् 4 P, संयु 2 P. **-ed**, *a.* संयुक्त, संबद्ध, अन्वित, सान्वय. 2 अविच्छेद, अविरत, अविच्छिन्न; 'a c. narrative' कथाप्रबंधः. **-ion**, *s.* संयोगः, अनुबंधः, संसर्गः, संगः ; 'in c. with' अनुषक्त, सहित, आश्रित्य. 2 संबंधः, संपर्कः, अन्वयः, संबंधः, समन्वयः. 3 बंधुः, बांधवः, ज्ञातिः ; 'to have c. with' संयम् 1 A, अभिगम् 1 P.

Connive, *v. i.* (at) कामतः उपेक्ष् 1 A, ज्ञानं निह्नु 2 A. 2 क्षम् 1 A, सह् 1 A. 3 अक्षि संकुच् 1 P. **-ance**, *s.* उपेक्षा, ज्ञानापह्नवः, कामतः उपेक्षा. 2 क्षमा. 3 अक्षिसंकोचनं.

Connoisseur, *s.* गुणज्ञः, परीक्षकः, अभिज्ञः.

Connubial, *a.* वैवाहिक (की *f.*); दंपती in comp. ; 'c. love' दंपतीस्नेहः.

Conquer, *v. t.* जि 1 P. वि-परा-जि 1 A, अभिपराभू 1 P. 2 निग्रह् 9 P, नि-सं-यम् 1 P, दम् c. (दमयति), वशीकृ 8 U, स्वायत्तीकृ ; 'one who has c. ed his passions' जितेंद्रियः, संयतेंद्रियः, वशी, दांतः, संयमी. **-able**, *a.* जेय, अभिभवनीय. **-or**, *s.* जेतृ *m.*, विजेतृ, जयिन् *m.*, जित् in comp.; विश्वजित् '.. of the world' **-Conquest**, *s.* जयः, विजयः, वशीकरणं, अभिभवः, जयनं, स्वायत्तीकरणं. 2 जितप्रदेशः.

Consanguineous, *a.* एकशरीर, एकपिंड, सपिंड, सगोत्र. **-Consanguinity**, *s.* सगोत्रता, सपिंडता ; एकशरीरान्वयः, संबंधित्वं.

Conscience, *s.* सदसद्विचारशक्ति *f.*, संज्ञानं; oft. ex. by मनस् *n.*, अंतःकरणं; 'biting of c.' पश्चात्तापः, मनस्तापः. **-Conscientious**, *a.* निर्व्याज, अमाय, शुद्धमति, न्यायपरायण, ऋजुप्रकृति. 2 पुण्यात्मन् , पुण्यशील, न्यायवर्तिन्. **-ly**, *adv.* शुद्धमनसा, निर्व्याजं, शुद्धभावेन. **-ness**, *s.* मतिशुद्धि *f.*; शुचिता, पुण्यशीलत्वं.

Conscionable, *a.* न्याय्य, योग्य यथार्थ. **-Conscionably**, *adv.* यथार्थं, धर्मतः, न्यायेन.

Conscious, *a.* Ex. by ज्ञ, विद् or अभिज्ञ in comp. or by verbs for 'know' q. v. 'not c. of pain' वेदनानभिज्ञः; 'I am perfectly c. of my defects' स्वदोषान् दृढं खलु जाने. 2 सचेतन, सतर्क, ज्ञानिन्, प्रतिबोधवत्; 'to be c. of' ज्ञा 9 P ; विभू c., (नात्मानमपि विभावयति S. 4), चित् 10 A; See **Know**. **-ly**, *-adv.* ज्ञानात् , बुद्धिपूर्वं, ज्ञानतः, कामतः. **-ness**, *s.* ज्ञानं, उपलब्धि *f.*, चेतना, चैतन्यं, संज्ञा, वेदनं, अनुभवः, बोधः, प्रतिबोधः.

Conscript, *s.* नवयोद्धृ *m.* **-s.** लिखितनामन्.

Consecrate, *v. t.* (an idol) प्रतिष्ठा c. (प्रतिष्ठापयति); पवित्रीकृ 8 U, संस्कृ, अभि-अनु-मंत्र् 10 A, (वामदेवानुमंत्रितोऽश्वः U. 2.). 2 अभिषिच् 6 P, प्रोक्ष् 1 P. 3 उप-प्र-वि-नियुज् 7 A, 10, निक्षिप् 6 P, वि-उत्-सृज् 6 P, उपकॢप् c. **-a.**, **-ed**, संस्कृत, प्रतिष्ठापित, विनियोजित, उपकल्पित. **-or.** *s.* संस्कर्तृ *m.*, प्रतिष्ठापकः. **-ion**, *s.* संस्कारः. प्रतिष्ठापनं. 2 उत्सर्गः, विनियोगः, उपयोगः.

Consecution, *s.* क्रमः, अनुक्रमः, प्रबंधः, अन्वयः, परंपरा, श्रेणी, माला. **–Consecutive,** *a.* क्रमागत, अनुपूर्व; अविरत, निरंतर, सप्रबंध, संतत. **–ly,** *adv.* क्रमेण, यथाक्रमं, यथापूर्व; अविरतं, अविच्छेदं. **–ness,** *s.* आनुपूर्व्यं, अविच्छेदः, प्रबंधः, संततता.

Consensus, *s.* बहुजनसंमति *f.*

Consent, *v. i.* सं-अनु-मन् 4 A, अनुरुध् 1 A, अनुज्ञा 9 U; ग्रह् 9 P, स्वीकृ 8 U; *See* **Agree.** **–***s.* संमति *f.* -तं, अनुज्ञा, अनुमोदनं. **2** मतैक्यं, एकचित्तता, ऐकंयं. **3** इच्छा, कामः; 'against one's c.' अनिच्छया, संमतिव्यतिरेकेण, बलात्, बलेन; 'c. in writing' संमतिपत्रं; 'take the c. of' अनुमन् c., (भूयोपि सर्वाञ्जनमनुमानयिष्यामि S. 3). **–ient,** *a.* एकमत, एकचित्त, संमत. **–ingly,** *adv.* संमत्या; कामतः, संमतिपूर्वं.

Consentaneous, *a.* *See* **Fit**

Consequence, *s.* फलं, परिणामः, उदर्कः, उत्तरं, उत्तरफलं. **2** गौरवं, महिमन् *m.*, गुरुता, प्रतिष्ठा, प्रभावः; 'of no c.' निरर्थक, यत्किंचन. **3** सिद्धि *f.*; कार्यं, प्रयोजनं, निमित्तं. **4** अनुमानं, ऊहनं, अभ्यूहः; 'in c. of this' अतः, अस्मात्कारणात्, अस्माद्धेतोः, अनेन हेतुना; 'as a c. of thy efforts' तव यत्नसामर्थ्यात्; 'immediate c.' सांदृष्टिकं; 'necessary c.' कार्यवशः 'visible c.' दृष्टार्थः. **–Consequent,** *a.* आनुषंगिक (की *f.*), अनुवर्तिन्; oft. ex. by फलं; 'c. upon his coming' तदागमनफलं. **–***s.* अनुषंगः, फलं, परिणामः. **–ial,** *a.* आनुषंगिक, अनुवर्तिन्. **2** मानिन्, सगर्व; *See* **Arrogant.** **–ly,** *adv.* इति हेतोः, अतः, तन्निमित्तं, तदनुसारेण; तदर्थं, इति, अनेन हेतुना, अस्मात्कारणात्.

Conserve, *v. t.* संरक्ष् 1 P, पा c. (पालयति), संधृ 10, गुप् 1 P. **2** संधा 3 U, उपस्कृ 8 U, **–***s.* मिष्टं, मोदकः, संधितं, उपस्करः, व्यंजनं. **–ation,** *s.* रक्षा, संरक्षणं, पालनं, गुप्ति *f.*, क्षेमः. **–ative,** *a.* संरक्षक, पालक **2** नवविद्वेषिन्, स्थितिपालक. **–ator,** *s.* रक्षकः, पालकः. **–atory,** *s.* रक्षास्थानं, आधारः, रक्षणस्थानं-शाला.

Consider, *v. t.* विचर् c., विमृश् 6 P, आ-समा-पर्या-लोच् 10, वि-सं-चिंत् 10, समीक्ष् 1 A, (न धर्मवृद्धेषु वयः समीक्ष्यते K. v. 16); ध्यै 1 P, संदृश् 1 A, अवधृ 10, अवेक्ष् **2** मन् 4 A, संभू c., तर्क् 10, समर्थ् 10, विगण् 10, आकल् 10, (स्पर्शमपि पावनमाकलयति Ku. 108) **3** परीक्ष्, निरूप् 10, अवेक्ष्, अनुसंधा 3 U, वि-चिन्व् 3, 7 U. **4** पूज् 10, अर्ह् 10, मन् c., प्रत्युपकृ, सं परि-तुष् c. **–able,** *a.* अलीक, गुरु, अनल्प, प्रचुर, भूरि, महत्. **2** मान्य, आर्य, पूज्य. **–ably,** *adv.* अतीव, भूरि, अति-सु-pr., भृशं, अनल्पं, अत्यंतं. **–ate,** *a.* समीक्ष्य-विमृश्य-कारिन्. **2** कृतावधान, आहत, दत्तावधान, अप्रमत्त, अवहित. **–ately,** *adv.* समीक्ष्य, विमृश्य, अवेक्षया, अप्रमत्तं, अवधानतः, सावधानं. **–ation,** *s.* विचारः, विचारणा, आलोचना, विमर्शः, समीक्षा, चिंता. **2** विवेचनं, निरूपणं, चर्चा, परीक्षणं. **3** आदरः, अपेक्षा, अवेक्षा. **4** कारणं, निमित्तं, हेतुः. **5** गौरवं, गुरुता, प्रतिष्ठा. **6** पूजा, संभावना, आदरः. **7** प्रतिफलं, पारितोषिकं; 'in c. of' अपेक्षया in comp., समीक्ष्य, आलोच्य, विचार्य, प्रथममिति मेऽद्य भवतोऽपराधो मर्षयितव्यः (S 4); 'in c. of its being the first' &c.

Consign, *v. t.* निक्षिप् 6 P, न्यस् 4 U, धा 3 U, 1 P, ऋ c. (अर्पयति), प्रतिपद् c., 'c. to the flames' अग्निसात्कृ 8 U. **2** उप-प्र-विनियुज् 7 A, 10. **–ment,** *s.* अर्पणं, न्यसनं, प्रतिपादनं.

of, in) Ex. by मय, आत्मक, मय (यी *f.*) in comp.; 'Ojas c. s in abundance of compounds' समासभूयस्त्वमेतदोजः... ओजः; 'body's ornament c. s in true knowledge' सत्यज्ञानात्मकं शरीरभूषणं; *See* **Compose.** **2** संवृत् 1 A, संस्था-संभू 1 P. **–ence,** *s.* घनता, सांद्रता, श्यानता. **2** स्थिरता, दृढता. **3** अविरोधः, आनुरूप्यं. **–ency,** *s.* संगतता, संवादः, अविरोधः, आनुरूप्यं. **2** स्थिरता, अचापल्यं **–ent,** *a.* अविरुद्ध, सदृश (शी *f.*), योग्य, अनुरूप, संवादिन्; 'his conduct is c. with his words' तस्याचरणं (कर्म) वचसा न विवदते, वचसो न विरुद्धं, वचसा न विसंवदति; 'in -c.' विसंवादिन्, विरुद्ध; (परार्थसुखमवृतः) स्वार्थाविरोधेन (Bh. 1. 74) 'c. ly with their own interests.' **2** स्थिर, अचपल, अलोल. **3** दृढ, घन, सांद्र, श्यान. **–ently,** *adv.* अविरुद्धं, अविरोधेन, अनुसारतः. **–ing,** *a.* Ex. by मय (यी *f.*), आत्मक (आत्मिका *f.*) in comp.; 'c. for the most part' ex. by भूयिष्ठ affixed; 'assembly c. of learned men' अभिरूपभूयिष्ठा परिषद् (S. 1).

Consistory, *s.* पुरोहितसभा.

Consociate, *See* **Associate.**

Console, *v. t.* आ-सम् आ-श्वस् c., सां(शां)त्व् 10, विनुद् c., अभ्युपपद् 4 A, (रतिमभ्युपपन्नमातुरां K. iv. 25). **2** शोकमपह् 1 P, दुःख-नकृतिरस्य-*a.* कृ 8 U. **–ation,** *s.* आश्वासः-सनं, सांत्वनं, विनोदनं, समाश्वासनं. **–atory,** *a.* सांत्वनशील, आश्वासिन्, शोकापहारक, शांतिद, सुखावह **–er,** *s.* आश्वासकः, विनोदकः.

Consolidate, *v. t.* संहन् 2 P, एकीकृ 8 U, घनीकृ, संस्था c. (स्थापयति). **–***v. i.* घनीभू, स्थिरीभू, संहन् pass **–ion,** *s.* घनीकरणं-

भवनं, संहति *f.*, संस्थापनं, समाहरणं, एकीकरणं.

Consonant, *s.* व्यंजनं; 'conjunct c.' संयोगः, योगः. —*a.* अविरुद्ध, अनुसारिन्, अनुरूप, योग्य, अनुगुण. -ly, *adv.* अनुसारेण, अनुरूपं. —**Consonance,** *s.* अविरोधः, अनुसारः, अनुरोधः, आनुरूप्यं.

Consonous, *a.* एकताल, एकस्वर.

Consort, *s.* Husband or wife, q. v. 2 सहचारिन् *m.*, संगिन् *m.* —*v. i.* सह वस् or चर् 1 P; संगम् 1 A, संयुज् pass.; 'well c. ed' सुसंगत. —**ion,** *s.* साहित्यं, साहचर्यं, संसर्गः.

Conspectus, *s.* सारपत्रं, संक्षिप्तलेखः.

Conspicuous, *a.* व्यक्त, सुप्रकाश, सुस्पष्ट, पुरःस्फुरत् (ती-न्ती *f.*), प्रत्यक्ष. 2 उत्कृष्ट, निरतिशय, प्रमुख, विशिष्ट. -ly, *adv.* स्पष्टं, व्यक्तं; विशिष्टतया. —ness, *s.* व्यक्तता, स्पष्टता, विशिष्टता, उत्कृष्टता.

Conspire, *v. i.* उपजप् 1 P. कूटं रच् 10. कुसाहित्यं कृ 8 U, कूटार्थं संशप् 1 U. 2 संमिल् 6 P, अनुकूल *a.* भू; "all things c.-ed to make him happy' सर्वं तस्य सुखायाकल्पत-अभवत्. —**acy,** *s.* उपजापः, कपटप्रबंधः, कुसाहित्यं, कुमंत्रणा; 'c. against the king' राजद्रोहः, द्रोहः. —**ator,** *s.* उपजापकः, कुसंसर्गिन् *m.*; संशप्तकः, शपथबद्धः. 2 राजद्रोहिन् *m.* 3 विश्वासघातकः.

Constable, *s.* दंड-यष्टि-धरः; राजपुरुषः.

Constant, *a.* स्थिर, दृढ, अचल, निश्चल. 2 शाश्वत (ती *f.*), सतत, प्रसक्त, अविरत, अनवरत, नित्य, सनातन (नी *f.*), निरंतर; 'c. wife' सती, पतिव्रता. -ly, *adv.* सततं, अनवरतं, अविरतं, अभीक्ष्णं, नित्यं, अनिशं, अजस्रं, सर्वदा, सर्वकालं. —**Constancy,** *s.* स्थैर्यं, स्थिरता, निश्चलता, दृढता. 2 अभिनिवेशः, निर्बंधः. 3 सातत्यं, अविरामः, नैरंतर्यं. 4 दृढा भक्तिः, दृढसौहृदं.

Constellation, *s.* राशिः, राशिनक्षत्रं; तारासमूहः, भगणः.

Consternation, *s.* संत्रासः, भीति *f.*, व्याकुलत्वं, साध्वसं, उद्वेगः, संभ्रमः.

Constipate, *v. t.* अवरुध् 7 U, अवष्टंभ् 9 P, बंध् 9 P, पिनह् 4 P. 2 निबिडीकृ 8 U. —**ion,** *s.* मलावरोधः, मलावष्टंभः, विड्ग्रहः, बद्धकः, बद्धकोष्ठः.

Constitute, *v. t.* रच् 10, निर्मा 3 A, विधा 3 U; gen. ex. by आत्मक, रूप, मय (यी *f.*) in comp., or by भू 1 P, अस् 2 P; 'we c. thy army' तव सैन्यं वयं स्मः; 'what c. s greatness' महिमा केन जायते; *See* **Compose.** 2 संस्था c. (स्थापयति), अधिकृ c.: नियुज् 7 A. 10, समाविश् 6 P. —**ion,** *s.* रचना, घटना, निर्माणं. 2 अवस्था, दशा, रूपं, वृत्ति *f.*; भावः. 3 व्यवस्था, विधिबंधनं, नियमः. 4 राजनीति *f.*. राज्यव्यवस्था. 5 प्रकृति *f.*, स्वभावः, शारीरावस्था; अल्पप्रकृति-स्वभावः; 'of a sickly c.' अल्परोगिन्, अशक्त, प्रकृतिदुर्बल. —**ional,** *a.* विध्यनुसारिन्, व्यवस्थानुरूप. 2 प्रकृति in comp. —**ionally,** *adv.* विध्यनुसारेण, व्यवस्थानुपूर्व्यं. —**Constituent,** *a.* घटक, रचक; 'c. parts' घटकावयवाः, घटकाः, अंगानि. 2 वास्तव (वी *f.*), सारभूत; 'c. members of a state' राज्यांगानि. —*s.* Ex. by *a.* 2 नियोजकः.

Constrain, *v. t.* बलात्कृ c., प्रवृत् c., प्रेर् c.; gen. ex. by causal of verbs; *See* **Compel.** 2 नि-अव-रुध् 7 U, नियंत्र् 10, नि-सं-यम् 1 P; 'c. ed silence' बलाद्धृतं मौनं; 'c. ed to be silent' नियंत्रितवाक्, यंत्रितकथ. —**Constraint,** *s.* बलं, बलात्कारः; 'by c.' बलात्, बलेन, अनिच्छन् *a.*, प्रसह्य. 2 अवश्यकता. 3 यंत्रणा, निरोधः, अवरोधः; 'c. of modesty' ह्रीयंत्रणा.

Constrict, *v. t.* संकुच् 1 P, आकुंच् c., संहृ 1 P. —**ion,** *s.* संकोचः. आकुंचनं, संहरणं.

Constringe, *v. t. See* **Constrict.**

Construct, *v. t.* निर्मा 3 A, 2 P, or c. (मापयति), रच् 10, विधा 3 U, घट् c. (घटयति), प्रक्लृप् c., कृ 8 U. —**ion,** *s.* रचना, निर्माणं, विधानं, &c. 2 अन्वयः, संबंधः, पदयोजना-नं. 3 अर्थः, आशयः; 'do not put a bad c. upon his words' तस्य वचांसि दुरर्थं मा कल्पय-आरोपय. —**ive,** *a.* निर्मातृ, प्रकल्पक, निर्माण or विधान in comp.; निर्माणचातुर्यं 'c. skill' &c.

Construe, *v. t.* अन्वयं कृ 10, अर्थं व्याख्या 2 P, युज् 10; तत्परतयैव वेदांतवाक्यानि योजयंति (S. B. 91) 'c. as referring to it'; 'to be c. ed' संबंध् pass., (इदं पदमेतेन संबध्यते).

Constupration, *s.* कन्यादूषणं, धर्षणं, बलात्काराभिगमः.

Consubstantial, *a.* एकशरीर, एकमूर्ति.

Consult, *v.* संमंत्र् 10 A, संवद् 1 P or c., संभाष् 1 A. 2 विमृश् 6 P, चिंत् 10, विचर् c.; 'you must c. public good also' जनहितमपि तावत् त्वया मनसि कार्यमेवावेक्षणीयं; 'do not c. your private good' स्वहितपरायणो मा भूः; 'let astrologers be c. ed' सांवत्सरिकैः संवादयतात्; 'you have given this order, having c. ed (with) my very heart' मम हृदयेन सह संमंत्र्य व्यवसितवानसि (Mu. 1); 'c. with oneself' मनसा विचर् c., आत्मना चिंत् 10. 3 निरूप् 10, समीक्ष् 1 A, आ-पर्या-लोच् 10; 'in c.

ing a horoscope' जन्मपत्रिकां विमृशन्, पत्रिकावलोकनेन शुभाशुभं पर्यालोचयन्. **-ation,** *s.* मंत्रणा-णं, विचारणं, विमर्शः, विचारः; आलोचनं, संवादः; 'private c.' गूढमंत्रणं. **-ative,** *a.* संमंत्रय; मंत्रणयोग्य.

Consume, *v. t.* क्षै c. (क्षपयति), विनश् c. 'c. by fire' निर्दह् 1 P. 2 उपभुज् 7 A; 10, उपयुज्य-उपभुज्य-निरवशेषीकृ 8 U. **-v. i.** क्षि pass., नश् 4 P, अवसद् 1 P, परिहा pass. **-er,** *s.* नाशकः; विनियोजकः. **-Consumption,** *s.* क्षयः, शोषः, यक्ष्मन् *m.* 2 नाशः, क्षयः, अवसादः. 3 उपयोगः, उपभोगः, व्ययः, विनियोगः. **-Consumptive,** *a.* क्षयिन्-क्षयरोगिन्.

Consummate, *v. t.* समाप् c.; *See* **Complete.** **-a.** संपूर्ण, निखिल, अन्यून. 2 परम, उत्कृष्ट, अग्रणीः; 'a c. rogue' शठाग्रणीः. **-ion,** *s.* समापनं, निष्पत्ति *f.*, सिद्धि *f.* 2 उत्कर्षः, परमा गतिः.

Contact, *s.* सं-,स्पर्शः, संपर्कः, संसर्गः, संयोगः, आसंगः, व्यतिकरः, परामर्शः; 'in close bodily c.' अंगांगि *ind.*

Contagion, *s.* स्पर्शः, स्पर्शसंचारः. **-Contagious,** *a.* स्पर्शजन्य, स्पर्शसंचारिन्, संस्पर्शज, संपर्कीय; 'a c. disease' मारि.

Contain, *v. t.* धृ 1 P, 10, आदा 3 A, परिग्रह् 9 P, धा 3 U, भृ 3 U; 'c. ing' ex. by धर-धारिन्-भृत् in comp.; 'c. ing water' तोयभृत्; oft. ex. by गर्भ, पूर्ण, आत्मक in comp.; अंबुगर्भः मेघः, शुकगर्भकोटरं, अमृतपूर्णं पात्रं, &c. 2 निवार् 10, संयम् 1 P, निग्रह् 9 P; 'he could not c. his great joy' गुरुः प्रहर्षः प्रबभूव नात्मनि (R. III. 17). **-ed,** *a.* धृत, अंतर्गत, अंतर्भूत, अंतर्गर्भित; वर्तिन्, स्थ in comp. **-er,** *s.* आधारः, धारिन्-भृत् in comp., 'the relation between c. and contained' आधाराधेयभावः.

Contaminate, *v. t.* दुष् c. (दूषयति), लिप् 6 P, कलंकयति-मलिनयति (D.). **-ed,** *a.* भ्रष्ट, दूषित, कलंकित, अपवित्र. **-ion,** *s.* दूषणं, कलंकः; अशौचं, भ्रष्टता, भ्रंशकारणं.

Contemn, *v. t.* अवमन् 4 A, अवज्ञा 9 U, अवधीर् 10 A, तिरस्कृ 8 U, अवगण् 10, न आदृ 6 A, उपेक्ष् 1 A, लघूकृ, तृणाय मन्, परिभू 1 P. **-er,** *s.* अवमंतृ *m.*, तिरस्कर्तृ *m.* **-Contempt,** *s.* अवज्ञा, अवमानः-मानना, अवधीरणा, तिरस्कारः, अवमानना, अनादरः, परिभवः, उपेक्षा, अवहेलनं-ना. **-ible,** *a.* अवमंतव्य, तिरस्कार्य. 2 क्षुद्र, निकृष्ट, नीच; 'to make oneself c.' आत्मानं तिरस्कारास्पदं कृ, अवज्ञाभाजनं भू. **-uous,** *a.* अवमानिन्, उपेक्षक, परिभाविन्, परिभावुक (की *f.*); सावज्ञ, सावमान. **-uously,** *adv.* सावज्ञं, सावमानं, उपेक्षया, सतिरस्कारं.

Contemplate, *v.* चिंत् 10; ध्यै 1 P; मनसा विचार् c., विमृश् 6 P. 2 निरूप् 10, निर्वर्ण् 10, अवेक्ष् 1 A, संदृश् 1 A, आलोच् 10, आलोक् 1 A, 10. 3 संकल्प् c., भू c. **-ion,** *s.* ध्यानं, चिंता, भावना, आलोचनं, विचारणा, विमर्शः; 'to be or have in c.' अभिप्र-इ 2 P, उद्दिश् 6 P. **-ive,** *a.* ध्यानपर, चिंताशील, & sim. comp.; भावितात्मन्, चिंतापर, समाधिस्थ. **-or,** *s.* ध्यातृ *m.*

Contemporary, *a.* or *s.* समकालीन, एककालीन, समानकालः.

Contend, *v. i.* संयत् 1 A, विग्रह् 9 P, कलहायते (D.), विरुध् 7 U, प्रतिकृ 8 U, विवद् 1 A, युध् 4 A, स्पर्ध् 1 A. 2 वाग्युद्धं कृ, प्रत्यवस्था 1 A, (अत्रापरे प्रत्यवतिष्ठंते S. B. 57). 3 यत्-चेष्ट् 1 A. **-er,** *s.* विपक्षः, प्रतियोद्धृ *m.*, विवादिन् *m.*, प्रतियोगिन् *m.*, प्रतिपक्षः. **-ing,** *a.* विरोधिन्; विवदमान, कलहशील. **-Contention,** *s.* विवादः, विग्रहः, कलहः, कलिः. विप्रतिपत्ति *f.*, वाग्युद्धं; विप्रलापः; 'point (bone) of c.' विवादविषयः-वस्तु *n.* 2 संघर्षः, स्पर्धा. **-Contentious,** *a.* कलहप्रिय, विवादिन्, विरोधिन्, कलह-विवादशील.

Content, *a.* सं-,परि-,तुष्ट, तृप्त, निःस्पृह, वितृष्ण, प्रीत, प्रशांत, हृष्ट; 'to be c.' तुष् 4 P, तृप् 4 P, संपरि-°; 'is c. with even little' स्वल्पकेनापि तुष्यति; 'poor and c. is rich and rich enough' संतोष एव पुरुषस्य परं निधानं. **-v. t.** तुष् c., तृप् c., सं-परि-°, नंद् c., प्री 9 P; 'c. s the eyes' कृतार्थयति चक्षुः. **-s.**, **-ment,** *s.* सं-,परि-,तोषः, तृप्ति *f.*, प्रीति *f.*, अस्पृहा, वितृष्णा, धृति *f.*, काम निवृत्ति *f.*; 'water to the heart's c.' प्रकामजलं. 2 (c. s) धनफलं (गोलस्य); द्रव्यं, अंतर्गतं; 'c. s of a letter' लेखार्थः; 'if so, I shall know its c. s' तेन ह्यस्य गृहीतार्था भवामि (V. 2); 'table of c. s' सूचीपत्रं, अनुक्रमणिका. **-ed,** *a.* तुष्ट, तृप्त, प्रीत, &c.; 'keep c.' अनुरंज् c., प्री 9 P. **-edly,** *adv.* प्रीत्या, संतोषेण, तुष्ट्या.

Conterminous, *a.* सीमावासिन्, समीप-निकट-वर्तिन्, पर्यंतस्थ.

Conterraneous, *a.* एकदेशज, सदेशज.

Contest, *v. i.* युध् 4 A, विवद् 1 A. **-v. t.** प्रतिकूलयति (D.), प्रति-वि-रुध् 7 U: *See* **Contend.** **-s.** कलहः, कलिः, विवादः, वाग्युद्धं, विप्रलापः, विप्रतिपत्ति *f.*, 'subject of c.' वादबीजं, विवादास्पदं, वादविषयः. **-ed,** *a.* वादग्रस्त, वादविषयीभूत; 'un-c. possession' अपरवोज्झितो भोगः (V. M. 11).

Context, *s.* अन्वयः संदर्भः, संबंधः, प्रकरणं (S. B.); नात्रास्माकं प्रकरणं वर्तते &c. **-e**

साभ्रूढ, संचित, संयुक्त. **-ure,** *s.* संस्थिति, *f.*, विन्यासः.

Contiguity, *s.* संनिकर्षः, सन्निधिः, सन्निधानं, समीपता, नैकट्यं. **-Contiguous,** *a.* सन्निकृष्ट, समीप, सन्निहित, संलग्न, आसन्न, समीपस्थ, समीप-निकट-वर्तिन्; 'c. ground' पर्यंतभूमि *f.*, परिसरः. **-ly,** *adv.* समीपे-पे, संनिकृष्टं, परिसरे.

Continent, *a.* जितेंद्रिय, संयत, संयमिन्, यत-मैथुन, उर्ध्वरेतस्, निवृत्तकाम, वशिन्, व्रत. **2** परिमित. **-s.** वर्षः-र्षं; 'c. of India' भरतवर्षः; महाद्वीपः-पं. **-al,** *a.* महाद्वीपिय, वर्षीय **-Continence,** *s.* संयमः, इंद्रियनिग्रहः, दमः, जितेंद्रियत्वं, वशित्वं.

Contingency, *s.* दैवयोगः-घटनं, दैवं, यदृच्छा, **2** अतर्कितोपनतः वृत्तांतः; oft. ex. by words for 'doubtful' q. v. **-Contingent,** *a.* अनिश्चित, संदिग्ध, दैवायत्त, दैववश, आगंतुक-आपातिक (की *f.*); अतर्कितोपनत, असमर्थितोपनत. **-s.** भागः, अंशः. **2** सैन्यदलं. **-ly,** *adv.* दैवात्, दैववशात्, यदृच्छया, अतर्कितं.

Continue, *v. t.* प्रवृत् c., प्रसंज् c., प्रस्तु 2 U or c., निर्वह् c. **2** प्रतन् 8 U, दीर्घीकृ 8 U. **-v. i.** प्रवृत् 1 A; gen. ex. by आस् 2 A, स्था 1 P, with present part. or not 'cease' q. v.; 'he c. ed to quarrel' कलहं कुर्वन्नास्त, कलहं कुर्वन्न व्यरमत्. **-al, -ous,** *a.* प्रसक्त, निरंतर, अविरत, अविच्छिन्न, संतत, सतत, नित्य, सनातन, अश्रांत; 'a c. story' कथाप्रबंधः. **-ally, -ously,** *adv.* नित्यं, सर्वदा, सततं, अनवरतं, अविश्रांतं, &c. **-ance, -ation, -ity,** *s.* प्रबंधः, प्रसक्ति *f.*, अविरामः, अविच्छेदः, सातत्यं, संतानं, अनुबंधः; 'c. of sorrow' शोकानुबंधः; 'c. in life' स्थिति *f.*, अवस्थानं, जीवितं; 'continuation (of a story)' शेषः, उत्तरभागः-खंडः परिशेषः; श्रेणि, अनुक्रमः. **-ator,** *s.* प्रवर्तकः, निर्वाहकः, उत्तरसाधकः.

Contort, *v. t.* आकुंच् c., वक्रीकृ 8 U, कुटिलीकृ; 'having the features c. ed' विकृताकारः. **-ion,** *s.* आकुंचनं, वक्रता, वैरूप्यं, विकृति *f.*

Contour, *s.* आकारः, रूपं. **2** परि(री)णाहः, परिधिः; 'covering the c. s of the breasts' स्तनयुगपरिणाहाच्छादिन् (S I).

Contraband, *a.* नि-प्रति-षिद्ध; धर्मविरुद्ध.

Contract, *v. t.* संकुच् 1 P. संकोचनी 1 P, आकुंच् c.; संहृ 1 P, समाकृष् 1 P, संक्षिप् 6 P, संपीड् 10 ग्रस्; 'the body being c. ed through fear', भयसंपिंडितांगत्वात् (Ka. 34); 'c. ing the eye' अक्षिसंकोचेन. **2** अधिगम् 1 P, उपगम्; 'I c. ed friendship with him' तेन सह मित्रत्वं उपगतः, सख्यमभजं; 'c. acquaintance' परिचयं कृ; 'c. debt' ऋणं कृ, ऋणग्रस्त *a.* भू; 'c. a disease' व्याधिना अभिभू pass.; 'c. marriage' विवाहं कृ, दारान्परिग्रह् 9 P. **-v. i.** आ-सं-कुच् pass., संकोचं, या-इ-गम्, संहृ-संपीड्-संक्षिप् pass. **2** समयं कृ 8 U, पणं-संविदंकृ, प्रतिपद् 4 A, संविद् 2 P. **-s.** समय, संविद् *f.*, नियमः, पणः, अभ्युपगमः; 'written c.' नियमपत्रं; 'a sale c.' क्रयपत्रं; 'marriage c.' वाग्दानं, वाग्निश्चयः. **-ed,** *a.* आकुंचित, संक्षिप्त, संहृत, संपीडित. **2** संकट, निरायत, संबाध. **-ion,** *s.* संकोचः-चनं, आकुंचनं, समाकर्षः, संपीडनं, संवृत्ति *f.* **2** संक्षेपः-पणं. **-or,** *s.* कृतसंविद् *m.*, नियमकृत् *m.*, पणकर्तृ *m.*

Contradict, *v. t.* विरुध् 7 U, प्रति-नि-षिध्, 1 P, प्रत्याख्या 2 P, पराहन् 2 P, प्रतीपायते (D.); 'c. oneself' विप्रवद् 1 U, विसंवद् 1 P. **-ion,** *s.* विरोधः, प्रतिषेधः, प्रत्याख्यानं, विपक्षता, प्रतिबंधः, प्रतिकूलता. **2** प्रतिवादः, वचनविरोधः. **3** विप्रलापः. विरोधोक्ति *f.* **4** असंगति *f.*, विसंवादः, विरुद्धता. **-ory,** *a.* विरुद्ध, विरोधिन्, विपरीत, विरुद्धार्थ, प्रतीप, विसंवादिन्; परस्परविरुद्ध-विरोधिन्. **2** परस्परपराहत, संकुल, क्लिष्ट.

Contradistinguish, *v. t.* विरुद्धगुणैः विशिष् 7 P, or c. **-Contradistinction,** *s.* विपरीतता, व्यतिरेकः, विपक्षता.

Contraposition, *s.* संमुखस्थिति *f.*; प्रतिष्ठापनं.

Contrary, *a.* (in direction) संमुखागत, प्रतीप; gen. ex. by प्रति pr.; 'c. wind' प्रतिवातः, प्रतीपपवनः. **2** प्रतिकूल, विरोधिन्, प्रति-वि-लोम, प्रतीप, विपरीत, विरुद्ध, विपक्ष, वैरिन्; oft. by इतर in comp.; 'the c. of true' सत्येतर. **-s.** विपर्ययः, विपरीतं, विपर्यासः, व्यतिक्रमः. **2** प्रतिपक्षः, 'c.-wise,' 'on the c.' प्रत्युत, पुनः, परंतु; 'to the c.' विपरीततया. **-adv.** **-ly,** **-adv.** विपरीतं, विरुद्धं, प्रतिकूलं; 'c. to usage' आचारविरुद्धं, &c. **-Contrariety,** *s.* वैपरीत्यं, विरोधः, विपर्ययः, प्रतिकूलता, विपक्षता, व्यत्ययः, व्यतिक्रमः.

Contrast, *v. t.* अंतरं-भेदं-दृश् c. or वर्ण् 10, परस्परविपर्ययेण उपमा 3 A. **-v. i.** विपर्यस् 4 P; विरुध् pass., विरुद्ध *a.* भू 1 P. **-s.** अंतरं, भेदः, विशेषः; oft. by क्व-क्व; क्व कंदमूलफलाशी शांतो मुनिजनः क्व कार्यं रागमयः प्रपंचः (Ka. 151). **2** विरोधः, प्रतिपक्षता, व्यतिरेकः, व्यत्ययः, वैलक्षण्यं.

Contravallation, *s.* परिखा, प्रतिकूपः.

Contravene, *v. t.* प्रति-वि-रुध् 7 U, व्याहन् 2 P, निषिध् 1 P; *See* **Oppose. -Contravention,** *s.* व्याघातः, निषेधः, वि-प्रतिरोधः, प्रतिबंधः.

Contretemps, *s.* उपद्रवः, व्यसनं, अंतरायः, प्रत्यूहः.

Contribute, *v. t.* स्वं स्वं अंशं दा 3 U. 2 (to) उपकृ 8 U, प्रवृत् c., कॢप् 1 A, (with dat.); *See* **Conduce.** **-ary,** *a.* एकराजाधीन. 2 प्रवर्तकः, पोषकः. **-ion,** *s.* अंशभाग-दानं. 2 अंशः, भागः, कृतांशः, उद्धारः. **-or,** *s.* अंशदातृ *m.* 2 साहाय्यकारिन् *m.*, उपकर्तृ *m.*, प्रवर्धकः.

Contrite, *a.* अनुशोकार्त, अनुशयपीडित, जातानुताप. **-ion,** *s.* पश्चात्तापः, अनुशयः, अनुतापः. **-ly,** *adv.* सानुशयं.

Contrive, *v. t.* चिंत् 10, निश्चि 5 U, निर्णी 1 P, उन्नी c., कल्प् c., युज् 7 U, 10, निरूप् 10, घट् c. (घटयति), संग्रथ् 10, विधा 3 U. **-v. i.** उपायं चिंत्, उपायं युज्. **-ance,** *s.* उपायः, प्रयुक्ति *f.*, साधनं, कल्पना, योजना, अप-व्यप-देशः, उपायचिंतनं, क्लृप्ति *f.* **-er,** *s.* उपायज्ञः, उपायचिंतकः.

Control, *v. t.* यम् 1 P, सं-नि-°, दम् c. (दमयति), वशं नी 1 P, जि 1 P, आवृ 5 U, वशीकृ 8 U, नि-विनि-ग्रह् 9 P, (passions &c.); निरुध् 7 U. 2 शास् 2 P, ईश् 2 A, (gen.); कथंचिदीशा मनसां बभूवुः (K. III. 34); 'could hardly c. their mind'; नियंत्र् 10; 'un-c. ed speech' अनियंत्रिता वाणी; 'un-c. ed weeping' निरर्गलाः प्रलापाः; 'with passions c. ed' जितेंद्रियः, संयमी, वशी. **-s.** संयमः, निग्रहः, निरोधः, नियंत्रणा, दमनं, 'self-c.' आत्मसंयमः, निग्रहः, इंद्रियजयः, वशित्वं. 2 अधिकारः, वशः, प्रभुत्वं; 'under the king's c.' राजाधीन, नृपायत्त; 'mental c.' अंतर्यमनं, मनोदंडः. **-ler,** *s.* शास्तृ *m.*, अध्यक्षः, अधिकारिन् *m.*, अधिष्ठातृ *m.*, ईशः, प्रभुः.

Controversy, *s.* वादः, विचारः, विवादः, वादानुवादः, विप्रतिपत्ति *f.*, वितर्कः, वाद्युद्धं, हेतुवादः. **-al,** *a.* विवादसंबंधिन्. वितर्किन्, (*s.*) in comp. **-alist,** *s.* वादिन् *m.*, तार्किन् *m.*, तार्किकः.

Controvert, *v. t.* प्रत्याख्या 2 P, अधरीकृ 8 U, निरस् 4 U, निराकृ, खंड् 10. 2 विवद् 1 A, विचर् c. **-ed,** *a.* वादग्रस्त, विवादविषयीभूत. **-ist,** *s.* वादिन् *m.*, नैयायिकः, विवादकृत् *m.*, तार्किकः,

Contumacious, *a.* धृष्ट, दुर्विनीत; दृप्त, सगर्व. 2 प्रतीप, प्रतिकूल, दुःशील. **-ly,** *adv.* सदर्प, धृष्टतया. **-Contumacy,** *s.* धृष्टता, दुर्विनीतता; प्रतीपता, दुःशीलता.

Contumely, *s.* अवज्ञा, निष्ठुर-परुष-वचनं, निष्ठुरता, निंदा, तिरस्कारः, अवमानना. **-ous,** *a.* परुष, निष्ठुर, निंदक, अवमानिन्. 2 सावज्ञ.

Contuse, *v. t.* मृद् 9 P, क्षुद् 7 U, पिष् 7 P, क्षण् 8 P, चूर्ण् 10. **-ion,** *s.* मर्दनं, निष्पेषः, क्षतं.

Conundrum, *s.* प्रहेलिका, प्रवह्लिका.

Convalescence, *s.* स्वास्थ्यं, निरामयः, रोगोपशमः, प्रकृतिलाभः. **-Convalescent,** *a.* निरामय, वीतरोग, प्रकृतिस्थ, नीरुज.

Convene, *v. t.* समाहे 1 P, साक्षात् एकत्र कृ 8 U, समानी 1 P; *See* **Assemble.** **-v. i.** संमिल् 6 P, सं-इ 2 P, एकत्र भू.

Convenience, *s.* सुखं, सोपकारत्वं, सुस्थता. 2 योग्यता, पात्रता; उचितसाधनं. 3 अवसरः, अवकाशः; 'in c. ed by the shutting of the lotus' अंभोजविनिमीलनदुःस्थितः (Rat. 2); 'when it suits your c.' यथावसरं, अवसरं प्राप्य, कार्यांतरांतरायमंतरेण. **-Convenient,** *a.* सुखकारक; उचित, अनुकूल, उपयुक्त; 'c. building' उचितसाधनयुक्तं भवनं; उपपन्न, यथाकाम, यथारुचि यथोचित. **-ly,** *adv.* सुखं, यथासुखं, यथावकाशं, यथावसरं; 'when may I c. ly see you' अन्यकार्यातिपातमंतरेण-कार्यांतराविरोधेन-भवान् कदा मया द्रष्टव्यः.

Convent, *s.* मठः, विहारः.

Conventicle, *s.* सभा, समाजः, मेलकः. 2 गूढसभा.

Convention, *s.* समयः, संविद् *f.*, नियमः, संकेतः. 2 सभा, संसद् *f.* 3 रूढि *f.*, लोकसंमति *f.*, आचारः. **-al,** *a.* लौकिक (की *f.*), लोकसंमत, निरूढ, रूढ, सांकेतिक (की *f.*); 'c. usage' जनरूढिः, लोकाचारः. **-alism,** *s.* रूढि *f.*, आचारविधि, *m.*

Converge, *a. v.* संनि-नि-पत् 1 P, एकस्थानं-एककेंद्रं-प्रतियां 2 P, (with loc.), पंथानः सिद्धिहेतवस्त्वय्येव निपतंति (R. x. 26); 'c. to thee alone.' **-ence,** *s.* समवायः, संनिपातः **-ent,** *a.* एककेंद्राभिमुख (खी *f.*), संनिपातिन्.

Converse, *v. i.* सं-आ-लप् 1 P, संभाष् 1 A, संवद् 1 P, संवच् 2 P. 2 संसर्गं कृ 8 U, संवस् 1 P, संगम् 1 A, संव्यवहृ 1 P. **-s.** संलापः, संकथा, संभाषणं, संवादः. 2 संसर्गः, व्यवहारः, संगमः. 3 विपर्ययः, विपरीतं, व्यत्यासः, व्यतिक्रमः. **-ant,** *a.* निपुण, चतुर, कुशल, विचक्षण, अभिज्ञ; कोविद, ज्ञ, वित् in comp.; पटु, विशारद; 'c. with law' स्मृतिज्ञः; 'not c. with love matters' अनभ्यंतरे आवां मदनगतस्य वृत्तांतस्य, (S. 3). **-ance, -ancy,** *s.* नैपुण्यं, पाटवं, चातुर्यं, विदग्धता, &c. **-ation,** *s.* आ-सं-लापः; संभाषणं, संकथा, संवादः; कथायोगः, विश्रंभालापः. 2 आचारः, व्यवहारः, वृत्ति *f.* **-ly,** *adv.* विपर्ययेण, व्यतिक्रमेण, व्यत्ययेन, प्रतीपं.

Convert, *v. t.* विकृ 8 U, अन्यथा कृ, परिवृत् c.; oft. ex. by सात्; 'c. to ashes' भस्मसात्कृ; *See* **Reduce.** 2 स्वधर्म-पक्षं-मतं त्याज् c. 'to be c. ed' परधर्म-

पक्ष-मत-ग्रह् 9 P, स्वधर्म &c. त्यज् 1 P. **3** प्र-उप-विनि-युज् 7 A, 10. **4** पापात् विरम् c. (रमयति) or निवृत् c., कुमार्गं त्यज् c. *-v. i.* अन्यथा भू 1 P, भावांतरं या 2 P or प्राप् 5 P. **2** स्वधर्म-पक्ष-मत-त्यज् 1 P, परधर्म &c. ग्रह् 9 P, or आश्रि 1 U or अवलंब् 1 A or स्वीकृ. **3** पापान्निवृत् 1 P or निवृत् 1 A *-s.* परधर्माश्रितः, परपक्ष-मत-अवलंबिन् *m.*, स्वधर्म-पक्ष-मत-त्यागिन् *m.* **-Conversion,** *s.* विकारः; विक्रिया, विकृति, *f.*, परिवर्तः, विपर्ययः, भावांतरप्रापणं; 'c. to ashes' भस्मसात्करणं, भस्मीभवनं. **2** परधर्माश्रयः, परधर्म-पक्ष-मत-अवलंबनं, स्वधर्म- &c. त्यागः. **3** पापान्निवृत्ति *f.*, कुमार्गत्यागः.

Convex, *a.* न्युब्ज, कूर्मपृष्ठाकार, आभोगवत्. **-ity,** *s.* न्युब्जता, आभोगः.

Convey, *v. t.* वह्-नी-हृ- 1 P, गम् c. (गमयति), प्राप् c संचर् c. **2** ऋ c. (अर्पयति), दा 3 U. **3** (sense) गम् c., प्रतिपद् c., सूच् c. **-ance,** *s.* यानं, प्रवहणं, वाहनं, रथः. **2** नयनं, प्रापणं, समर्पणं; 'deed of c.' समर्पणपत्रं, क्रयलेख्यं. **-er,** *s.* वाहकः, वाहिन् in comp.

Convict, *v. t.* अपराधं निर्णी 1 P, अपराधिन् *a.* स्था c. (स्थापयति), आधृष् c. *-s.*, *-a.*, **-ed,** *a.* निर्णीतापराधः, निश्चितदोषः, आधर्षितः, दृष्टदोषः. **-ion,** *s.* अपराधस्थापनं, अपराधनिर्णयः, दोषनिश्चयः, आधर्षणं.

Convince, *v. t.* प्रति-इ c., प्रतीतिं कृ 8 U, उरीकर्तुं आनी 1 P, अभिज्ञा c. (ज्ञापयति); 'he was c. ed of his mistake' स्वभ्रममुद्दिश्य तस्य प्रतीतिः समजनि or अयं भ्रम एवासीदिति तस्य निश्चयो जातः; ताः स्वचारित्र्यमुद्दिश्य प्रत्याययतु मैथिली (R. xv. 73) 'c. them of her purity.' **2** संदेहं निराकृ or निरस् 4 U or अपनुद् 6 P. **-ed,** *a.* जातनिश्चय-प्रत्यय, छिन्न-संशय; 'I am c. that' &c. इति मे निश्चयः, इत्यसंदेहपदं. **-ing,** *a.* निर्णायक, प्रत्ययजनक, संशयच्छेदिन्, निश्चायक. **-Conviction,** *s.* विश्वासः, प्रत्ययः, निश्चय. निर्णयः, दृढप्रत्ययः, दृढं मतं.

Convivial, *a* उत्सवसंबंधिन्, औत्सविक (की *f.*); 'a c. party' तुल्यभोजनं, स(सं)पीति *f.*

Convoke, *v. t.* समाह्वे 1 P, समाहृ 1 P, आह्वानेन एकत्र कृ 8 U. **-Convocation,** *s* समाह्वानं, समाह्वानविधिः. **2** सभा, समाजः, संसद् *f.*

Convolve, *v. t* आ-समा-वृत् c.

Convoy, *v. t.* रक्षार्थं अनुव्रज्, अनुगम् 1 P, अनु-परि सं-सह-चर् 1 P. *-s.* पथि रक्षकः, सहचरः, परि-अनु-चरः

Convulse, *v. t.* सं-वि-क्षुभ् c., कंप् c. **2** आकृष् 1 P, आकुंच् c., अप-तन् c., वि-आक्षिप् 6 P. **-ion,** *s.* सं-वि-क्षोभः, कंपः. **2** आक्षेपः, अपतानकः, आकर्षः. **-ive,** *a.* आकर्षक, आक्षेपकर (री *f.*), विक्षेपिन्; 'c. speech' गद्गदवाच् *f.*, गद्गदं; 'in a c. fit' आक्षेपाभिभूत.

Cony, *s.* शशः, शशकः.

Coo, *v. t.* कूज् 1 P, कु 2 P, 1 A, रु, रु 2 P.

Cook, *v. t.* पच् 1 P, श्रा 2 P, or c. (श्रापयति), श्री 9 P; 'c. food' अन्नं संस्कृ 8 U, सिध् c (साधयति), सिद्ध *a.* कृ; 'c. ing pot' पाकपात्रं, स्थाली; 'c. ed food' ओदनः-नं, सिद्धौदनः, सिद्धमन्नं. *-s.* पाचकः, सूपकारः, बल्लवः, सूदः. **-ed,** *a.* पक्व, सिद्ध, श्रृत, श्राण. **-ery,** पाककलाविद्या; पाकसिद्धि-निष्पत्ति *f.* **2** पचनं, पाकः. **-room,** *s.* पाकशाला, महानसः-सं.

Cool, *a.* शीतल, शीत, शिशिर, शीतस्पर्श, आर्द्र (fig.) मृदु, मृदु, सुखस्पर्श, कोमल; अनुष्ण अतिग्म, (rays). **2** प्रशांत, अनुद्वेग, धीर, अव्यग्र, असंभ्रांत, अव्याकुल. **3** वीतराग; *See* **Cold.** *-s.* शीतं, शीतलता; 'in the c. of evening' प्रशांते-अनुष्णे संध्यासमये. *-v. i.* शीतलीकृ 8 U, आर्द्रयति (D.), निर्वा c. (वापयति), आर्द्रीकृ, तापं हृ 1 P; अन्याहृश एव तेषां निर्वापयति शरीरस्पर्शः (Mal. 6); शरीरनिर्वापणाय (S. 3). **2** (down) प्र-उप-शम् c. (शमयति), ज्ञिम् c. **3** शिथिलीकृ, शिथिलयति (D.). *-v. i.* शीतलीभू 1 P, शीतीभू, शीतलायते (D.); **2** शिथिलीभू, शिथिलायते (D.). 'she will not let her love for you c. down' न सेतोगतमनुरागं शिथिलयति (V. 2). **3** प्र-उप-शम् 4 P, विरम् 1 P **-ing,** *a.* तापहर, निर्वापक, शांतिद, शीतल, सुखद. **-ly,** *adv.* असंभ्रमं, शांतचेतसा, अव्यग्रं, शांतं, निरुद्वेगं. **2** प्रकोपनं विना, बुद्धिपुरःसरं. **-ness,** *s.* शीतलता, आर्द्रता, 'c. of affection' विरागः, विरक्ति *f.*, अनुरागशिथिलता.

Coop, *s.* भाजनं, काष्ठभांड. **2** पीतंसः, पंजरः-रं. *-v. t.* (up) (पंजरे) निरुध् 7 U, बंध् 9 P, संयम् 1 P, नियंत्र् 10.

Co-operate, *v. i.* संभूय कृ 8 U, साहाय्यं दा 3 U, अन्येन सार्धं प्रयत् 1 A or व्यवसो 4 P, or चेष्ट् 1 A **-ion,** *s.* सहकारिता, सहोद्योगः, साहाय्यं, संभूय व्यवसायः. **-ive,** *a.* सहकारिन्, सहोद्योगिन्. **-or,** *s.* सहकारिन् *m.*, संभूयकारिन् *m.* सहोद्योगिन् *m.*

Co-ordinate, *v. i.* संवद् 1 P. *-v. t.* क्रमशः संनिधा 3 U, *-a.* सजातीय.

Coparcener, *s.* समांशिन् *m.*, संयुक्त-रिक्थिन् *m.*, अंशहरः, रिक्थाधिकारिन् *m.*, दायाद :

—Coparcenary, *s.* संसृष्टि *f.*, संसृष्टिता, समांशिता.

Copartner, *s.* समांशिन् *m.* अंशभाज् *m.*, संभूयकारिन् *m.* **—ship**, *s.* समांशिता; संभूय समुत्थानं.

Cope, *v. i.* (with) युध् 4 A, विग्रह् 9 P, विवद् 7 U, अभिपत् 1 P (with acc.); यंता गजस्याभ्यपतद्गजस्थं (R. VII. 37). 2 स्पर्ध् 1 A, संघृष् 1 P, अभिभू 1 P; *See* Compete. **—***s.* शिरस्त्राणं, मस्तकाच्छादनं.

Coping, *s.* प्राकारशीर्ष-शृंगं.

Copious, *a.* प्रचुर, सुचिष्ठ, बहु, विपुल, प्रभूत, पुष्कल, भूरि, बहुल. **—ly**, *adv.* बहु, भूरि, बहुशः, प्रचुरं, अति-सु-pr. **—ness**, *s.* बाहुल्यं, प्राचुर्यं, विपुलता, &c.

Copper, *s.* ताम्रं, ताम्रकं, शुल्बं, म्लेच्छं, वरिष्टं, उदुंबरं; ' c. coin ' पणः ; ' c. plate ' ताम्र-पत्रं-पट्टं-पटः; ' c. smith ' ताम्रकारः, ता-म्रिकः, ताम्रकुट्टकः, शौल्बिकः. **—y**, *a.* ताम्र (म्रा *f.*), ताम्रमय (यी *f.*).

Copperas, *s.* तुत्थं, मलीमसं.

Coppice, Copse, *s.* गुल्मावृतं स्थानं, जंगलं, तरुगहनं.

Copulate, *v. i.* मैथुनं-संगं-कृ 8 U, अभिगम् 1 P, संगम् 1 A. **—***v. t.* संयुज् 7 P, 10, संधा 3 U. **—ion**, *s.* मैथुनं, सुरतं, संभोगः, व्यवायः, रतिक्रिया. 2 संसर्गः, संपर्कः, सं-योगः. **—ive**, *a.* संयोग-संसर्ग-कारिन्. 2 उभ-यान्वयिन्.

Copy, *s.* प्रतिलेखः, प्रतिलिपि *f.*, हस्तलेखः, लिपि *f.* 2 मूलं. 3 एकग्रंथः, एकपुस्तकं. 4 अनु-करणं; ' c. right ' मुद्रणस्वामित्वं-स्वत्वं , मुद्रणाधिकारः. **—***v. t.* प्रतिलिपिं कृ 8 U, लिख् 6 P. 2 अनुकृ (with gen.). **—er, —ist**, *s.* लिपिक(का)रः, लेखकः, अक्षरचणः, अक्षर-चंचुः. 2 अनुकारिन् *m.* 3 शब्दचोरः.

Coquet, *v. t.* विलस् 1 P, विभ्रम् 1, 4 P, हावं-विलासं-कृ 8 U, ललिताभिनयं कृ. **—ry**, *s.* विलासः, विभ्रमः, हावः, लीला, ललि-ताभिनयः. **—Coquette**, *s.* विलासिनी, वि-लासवती, कामिनी, लीलावती.

Coral, *s.* विद्रुमः, प्रवालः.

Corban, *s.* ईश्वरार्पणं, उत्सर्गः.

Cord, *s.* रज्जु *f.*, दामन् *n.*, पाशः, शुल्वं, गुणः, सूत्रं, वटी. **—***v. t.* रज्ज्वा बंध् 9 P, or यंत्र् 10. **—age**, *s.* रज्ज्वादिसामग्री. **—ed**, *a.* पाश-रज्जु-बद्ध.

Cordial, *a.* दीपक, अग्निवर्धक; धातुपोषक. 2 दृढसौहृद, गाढपरिचय, सुशील (of persons) दृढ, गाढ, घन. **—***s.* अग्निवर्धनं; रुचकं, दीपकं-नं. **—ity**, *s.* सौहार्दं, सुशीलता, सौजन्यं, मित्रभावः, मैत्र्यं, सख्यं. **—ly**, *adv.* सौहार्देन, सुशीलवत्.

Cordon, *s.* आगमनिर्गमप्रतिषेधः.

Core, *s.* अंतरं, मर्मः, अंतर्भागः, हृदयं.

6

Coriander, *s.* धान्यं, धान्येयः. 2 (seed) छत्रा, धान्यकं, वितुन्नकं, कुस्तुंबरु *n.*

Cork, *s.* पिधानं, कूपीछिद्रपिधानं.

Cormorant, *s.* मद्गुः, ओतुरिकः, कुक्कुटिः, मुद्गुः.

Corn, *s.* धान्यं; ' growing c. ' सस्यं. 2 किणः, कदरः. 3 अन्नं, आहारः, जीवनसाधनं. ' c. mill ' धान्यपेषणी. **—y**, *a.* शुंगवत्.

Cornea, *s.* शुक्लमंडलं.

Corner, *s.* कोणः; अस्रः; ' c. of the eye ' अपांगः-गं, नयनोपांतः; ' c. of the mouth ' सृक्कन् *n.* 2 विविक्तस्थानं, निर्जनदेशः; ' c. stone ' प्रधान-कोण-प्रस्तरः; ' c. wise ' कोणाकोणि, अस्राश्रि.

Cornet, *s.* अश्विकनायकः. 2 आवेष्टनं, कोशः-षः.

Cornice, *s.* प्राकारशीर्ष-शृंगं.

Cornuted, *a.* (man) बंधकीभार्यः.

Corollary, *s.* अनुमानं; अपवादः, उपसिद्धांतः, उपलक्ष्यः.

Corona, *s.* रविप्रभितः-तेजोमंडलं-मुकुटाकारं.

Coronal, *s.* मुकुटं, किरीटः.

Coronation, *s.* अभिषेकः, राज्याभिषेकः.

Coroner, *s.* अपमृत्युकारणनिरूपकः.

Coronet, *s.* मुकुटं, किरीटः.

Corporal, *a.* कायिक-शारीरिक-दैहिक (की *f.*), शारीर (री *f.*); ' c. punishment ' देह-शरीर-दंडः. **—***s.* सेनाधिकृतः पुरुषः. **—ity**, *s.* देहवत्त्वं, शरीरवत्ता. **—ly**, *adv.* शरीरेण, देहतः.

Corporate, *a.* कृतसंसर्ग, संभूयकारिन्, संघात-वत्, संसृष्ट. **—ion**, *s.* ' a c. body ' श्रेणि-णी *f.*, समाजः.

Corporeal, *a.* देहिन्, शरीरिन्, वपुष्मत्, सदेह, सशरीर.

Corps, *s.* अनीकं, सैन्यदलं-गुल्मः, वृंदः.

Corpse, *s.* शवः-वं, कुणपः, प्रेतं, मृतशरीरं.

Corpulent, *a.* स्थूल, स्थूलकाय, पीन, पीवर, मेदस्विन्, मांसल; ' having a c. belly ' तुं-दिन्, तुंदवत्, तुंदिल, बृहत्कुक्षि, पिचंडिल. **—Corpulence**, *s.* पीनता, स्थूलता, मेद-स्विता, पृथुलता.

Corpuscle, *s.* अणुः, कणः, लवः, लेशः.

Correct, *v. t.* वि-परि-सं-शुध् c., निर्दोष *a.* कृ 8 U, प्रतिसमा-समा-धा 3 U; ' instantly c. ing himself ' सपदि स्वयमेव समादधत् ; प्रमृज् 2 P; ' c. one's bad conduct ' पा-पाद्विरम् 1 A, कुमार्गं त्यज् 1 P. 2 अनुशास् 2 P, दंड् 10. 3 प्रतिकृ, अपा-निरा-कृ. **—***a.* शुद्ध, निर्दोष, अभ्रांत. 2 सत्य, तथ्य, यथार्थ, अवितथ, यथातथ; ' c. in conduct ' साधु-वृत्त, निर्दोषाचरण. **—ion**, *s.* शोधनं, शुद्धि *f.*; समाधानं. 2 शासनं, दंडः-नं, निग्रहः. **—ive**, *a.* शोधक. 2 प्रतिक्रियाकृ, अपह-हर-in comp. **—***s.* प्रतिकारः, समाधानं. **—ly**, *adv.*

शुद्ध, निर्दोष. 2 सत्य, यथार्थ, यथावद्, साधु. -ness, s. शुद्धि f., शुद्धत्वं-ता, निर्दोषता, सत्यता, तथ्यता, यथार्थता. -or, s. शोधकः, संस्कर्तृ m. 2 शास्तृ-शासितृ m.; दंडनेतृ m. -Corrigible, a. शोधनीय; दंडनीय, समाधेय.

Correlation, s. परस्परसंबंधः, अन्योन्याश्रयः, व्यतिकरः. -**Correlative**, a. परस्परसंबद्ध, इतरेतरसंबंधिन्.

Correspond, v. i. (with) पत्रेण संवादं कृ 8 U, पत्रलेखनेन संवद् 1 P or व्यवहृ 1 P. 2 (to) संवद् 1 P, अनुरूप- सदृश (शी f.) a. भू 1 P; युज्-उपपद्-pass. See **Resemble**, 'his face c.s to that of Sitā' अस्य मुखं सीताया मुखेन संवदति (U. 4). -**ence**, s. पत्रसंवादः, पत्रविनिमयः. 2 संवादः, अनुरूपता, सादृश्यं. 3 संबंधः, संसर्गः, संपर्कः. -**ent**, a. अनुरूप, युक्त, सदृश, तुल्य, संगत, संवादिन्. -s पत्रेण संवादिन् m. 2 नियोगिन् m., प्रतिपुरुषः. -**ing**, a. अनुरूप, युक्त, सदृश.

Corridor, s. गूढ प्रच्छन्न-पथः.

Corrigendum, s. शुद्धिपत्रं.

Corrival, s. प्रतिपक्षः, प्रतिस्पर्धिन् m., प्रतियोगिन् m. -**ry**, s. प्रतिस्पर्धा, संघर्षः, प्रतियोगिता.

Corroborate, v. t. दृढीकृ 8 U, समर्थ् 10, प्रत्ययि (D.), प्रमाणीकृ. प्रमाणं दा 3 U, उपोद्बल् 10. -**ion**, s. दृढीकरणं, प्रमाणीकरणं, समर्थनं, उपोद्बलनं, प्रमाणं.

Corrode, v. t. क्षि 5 P or c., क्रमशः-शनैः-खाद् 1 P or नश् c. or विलॄ c. -**ent**, a. नाशक, क्षयकर (री f.). -**Corrosion**, s. क्रमशो विदारणं or नाशनं, क्षयः. -**Corrosive**, a. विदारक, नाशक. 2 तीव्र, तिग्म, प्रखर. मर्मभिद्, मर्मस्पृश्.

Corrugate, v. t. (त्वचं-चर्म) संकुच् 1 P; आकुंच् c., भंज् 1 P. -**ion**, s. त्वगाकुंचनं, चर्मसंकोचः; भंगीकरणं.

Corrupt, v. t. दुष् c. (दूषयति), भ्रंश् c., भ्रश् c., विकृ 8 U or c., मलिनयति (D.), कलुषयति (D.), अपपत् c.; 'the mind is c. ed in youth' यौवनारंभे कालुष्यमुपयाति बुद्धिः (Ka. 103); 'c. a woman' दुष् c., चारित्र्यं भ्रश् c., सतीत्वात् भ्रंश् c., दूष् 10. 2 पूतीकृ. 3 उत्कोचं दा 3 U, उत्कोचदानेन वशी-अनुकूली-कृ. -v. i. दुष् 4 P, पूतीभू 1 P. -a. दूषित, कलुष, पतित, दुष्ट, भ्रष्ट, कलुषित. 2 दुष्टमति, दुराचार, पापचेतस्, अंतर्दुष्ट, दुरात्मन्, दुराशय, पापबुद्धि. 3 पूति, पूतिगंधि, दुर्गंध. -**ion**, s. दूषणं, पातनं, मलिनीकरणं. 2 उत्कोचग्राहित्वं, धर्मभ्रष्टत्वं. 3 दुष्टता, दौरात्म्यं, भ्रष्टता, अंतर्दुष्टता, दौर्जन्यं. 4 अपभ्रंशः, अपशब्दः, अपभ्रष्टशब्दः. 5 पूति f., पूतता, दुर्गंधः. -**er**, -**ive**, a. दूषक, नाशक. -**ly**, adv. दुष्टं, दुष्टतया; सदोषं.

Corsair, s. समुद्रविप्लवः.

Corse, s. See **Corpse**.

Corset, s. चोलः-ली, कूर्पासकः, कंचुकः.

Corslet, s. वक्षस्त्राणं, कवचः-चं.

Cortege, s. परिवारः.

Cortical, a. त्वङ्मय (यी f.), त्वाच (ची f.).

Coruscate, v. i. स्फुर् 6 P, द्युत् 1 A; See **Shine**. -**ion**, s. स्फुरणं, स्फुरितं. -**Coruscant**, a. उज्ज्वल, भासुर.

Cosine, s. ज्या.

Cosmetic, a. कांतिवर्धक, शोभाजनक (नी f.), शोभावह. -s. अंगरागः.

Cosmical, a. जगत्संबंधिन्.

Cosmogony, s. विश्वोत्पत्ति f., जगत्सृष्टि f.

Cosmography, s. जगद्विवरणं-वर्णनं.

Cosmopolite, -**politan**, s. विश्वस्वामिन् m., सर्वत्रवासिन् m., जगन्मित्रं.

Cosmos, s. जगत् n., विश्वं.

Cost, s. मूल्यं, अर्घः, अर्हा. 2 व्ययः; 'even at the c. of one's life' प्राणव्ययेनापि; 'high c.' बहुमूल्यं, oft. by instr. of noun, (आत्मानं सततं रक्षेद्दारैरपि धनैरपि). 3 धनक्षयः. -v. t. मूल्येन ग्रह् 9 U or क्री 9 U, 'what does it c.' कियता मूल्येन विक्रीयते मत्; 'the house c. me 1000 Rs.' सहस्ररूपकेण मया गृहं क्रीतं; 'the marriage ceremony c. me much' बहुव्ययेन निष्पादितो विवाहविधिः; 'his obstinacy c. him dear' दुराग्रहात्तस्य अनर्थस्समभवत्; व्ययेन साध् 10; 'will c. the lives of' प्राणनाशं-व्ययं-आवह्. -**ly**, a. महार्घ, महार्ह, बहुमूल्य.

Costermonger, s. फलविक्रेतृ m.

Costive, a. आनद्ध, बद्धकोष्ठ, अवबद्धमल, निरुद्धविट्क. -**ness**, s. मलावरोधः, मलावष्टंभः, आनाहः, विड्-शुद्-ग्रहः.

Costume, s. वेशः, नेपथ्यं; See **Dress**.

Co-sufferer, s. समदुःखः, समदुःखभाज् m.

Cosy, a. सुखावह, हितकर, सुस्थित.

Cot, s. खट्वा, मंचः, पर्यंकः. 2 दोला, प्रेंखा. 3 **Cottage**, q. v.

Cote, s. व्रजः, शाला.

Coterie, s. एकविषयजनसंसर्गः-गणः.

Coquean, s. स्त्रीकर्मव्यापृतः.

Cottage, s. उटजः-जं, पर्णकुटिः-टी f., पर्णशाला, कायमानं, कुटीरः; 'c. girl' उटजनिवासिनी बालिका. -**er**, **Cotter**, **Cottier**, s. कुटीरस्थः, उटजवासिन् m.; ग्रामीणः.

Cotton, s. कार्पासः, तूलः, पिचुः, पिचुलः. 'made of c.' कार्पास a.; 'c. cloth' वस्त्रार्थं, कार्पासं, कार्पासिकं, बादरं; 'c. plant

कार्पासी, -y, *a.* तूलसंबंधिन्, कार्पासिक (की *f.*), (*s.*) in comp.

Couch, *s.* शयनं, शय्या, पर्यंकः, खट्वा, शेयः; *See* **Bed.** — *v. i.* शी 2 A, संविश् 6 P, ... आवसथ् 1 P, नि-पत्, —*v. t.* ... परिविश् 9 P, ... 10, ग्रथ् 9 P. 'c. ... in fair words' मधुरवचनग्रथितः (शिष्टः) ... low' सहशायिन्. **-ant**, *a.* शय, शायिन्

Cough, *s.* कासः, कासः, ... 'suffering from c.' कासिन् —*v.* ... 1 A, क्षु 2 P. **-er**, *s.* कासरोगिन्

Coulter, *s.* लाङ्गल, कुशिः

Council, *s.* सभा, समाज *f.* ... room' (chamber of c.) ... मंत्रगृहं **-lor**, *s.* सभासद् ...

Counsel, *s.* मंत्रणा, विचार ... विमर्शः, ... 2 उपदेश ... अनुशासनं 3 उपाय 4 Barrister ... —*v. t.* उपदिश् 6 P, मंत्र् 10 ... **-lor**, *s.* ... *m.* सचिव ... सचिवः 2 उपदेशक, उपदेष्टृ ... **-lorship**, *s.* साचिव्य, मात्रित्व

Count, *v. t.* गण् 10 (lit. and fig.) ... कल् 10, संख्या 2 P 2 मन् ... गण्-pass., 'c. on, upon' अवलम्ब् 1 A, आश्रि 1 U विश्वस् 2 P, ... 'I do c. upon your help' ... त्वय्येवेति ... 'c. ing upon your promise' ... —*s.* गणनं, गणना, संख्या ... 2 ... विषयः, ... **-less**, *a.* असंख्य, अगण्य, संख्यातीत, अनंत, ...

Countenance, *s.* मुखं, आननं, वदनं, आस्यं, वक्त्रं 2 आकारः, आकृति *f.*, ... 3 ... अनुग्रहः, ... अनुमोदनं. — *v. t.* अनुग्रह् 9 P ... आनुकूल्यं कृ ... 4 A, अनुमुद् 1 A, *See* **Encourage** also **-er**, *s.* उपकारकः, सहायः अनुग्राहिन् *m.*, अनुमोदकः.

Counter, *s.* गणनाफलकः 2 (गणनार्थं) ... वणिजां ... *adv.* प्रतिकूलं, विरुद्धं, विपरीतं, प्रतिलोमं. gen. by प्रति pr.; 'c. design' प्रत्युपायः; 'c. poison' प्रतिविषं

Counteract, *v. t.* मोघी-विफली-कृ 8 U, निवारय् 10, प्रतिकृ, प्रतिहन् 2 P, प्रति-विधा ... 7 U **-ion**, *s.* प्रतिक्रिया, ... प्रतिरोधः, प्रति-घात-घातः.

Counterbalance, *v. t.* तुलया धृ 1 P, तुल्यभारं ... कृ 8 U, समीकृ, संतुल् 10.

Counterblast, *s.* विरोधः, प्रतिरोधः.

Counterbuff, *v. t.* प्रति-अभि-हन् 2 P. —*s.* प्रतिघातः.

Counterchange, *v. t.* परस्परं परिवृत् c., विनि-मे 1 A. —*s.* परिवर्तः, विनिमयः, व्यतिहारः.

Countercheck, *s.* प्रतिरोधः, प्रतिबंधः.

Countercurrent, *s.* प्रतिस्रोतः ...

Counterevidence, *s.* विरुद्धसाक्ष्यं, प्रतिकूलसाक्ष्यं.

Counterfeit, *a.* कृत्रिम, कृतक, कापटिक, छाद्मिक (की *f.*); gen. by ... कपट, छद्म, कूट in comp., 'c. seal' कपटमुद्रा, कूटशासन, छद्मवेश, &c. —*v. t.* छद्म-कपट-कृ 8 U, अनुकृ; कृ with कपट-कूट in comp., 'c. a seal' कूटमुद्रां कृ; 'c. a document' कूटलेखं कृ; 'c. ing sleep' कपटसुप्त, ... निद्रायुक्तः; *See* **Feign.** 2 विडम्ब् 1 A, *See* **Cheat.** —*s.* कूटं, कपटं, छद्मन् *n.*, व्याजः 2 कूटलेख ... कूटकृत् *m.*, कूटलेख्यकारः 2 वंचकः, प्रतारकः. **-ly**, *adv.* सकपटं, सकूटं, मिथ्या, ...

Countermand, *v. t.* प्रत्यादिश् 6 P, विपरीताज्ञां दा 3 U. —*s.* प्रत्यादेशः, विपरीताज्ञा

Countermarch, *v. i.* ... 2 ... —*s.* प्रतियानं, प्रतीपयात्रा.

Countermark, *s.* प्रतिलक्षणं, प्रतिचिह्नं.

Countermine, *s.* प्रतिसुरंगा —*v. t.* प्रतिसुरंगां कृ 8 U

Counterpane, *s.* शयनास्तरणं ...

Counterpart, *s.* प्रतिरूपं, प्रतिमा, प्रतिबिंबं, प्रतिमूर्ति *f.*, (अहो ... S. I).

Counterplea, *s.* प्रत्युत्तरं प्रत्यभियोगः.

Counterpoise, **Countervail**, *v. t.* *See* **Counterbalance.** —*s.* तुल्यभारता, समतोलनं.

Country, *s.* *n.*, देशः, विषयः, राष्ट्रं, दिश् *f.*, आशा. 2 ग्रामः, जनपदः, (opposed to नगर, पुरं); 'c. folk' जानपदाः, ग्राम्याः; 'c. life' ग्रामवृत्ति, ग्रामवसतिः; 'native c.' जन्मभूमि *f.*, स्वदेशः; 'c. man' स्वदेशीयः, एकदेशस्थः, देशबंधुः; जानपदः, ग्राम्यजनः, ग्रामीणः; 'c. parson' जानपदपुरोहितः, ग्रामयाजकः.

County, *s.* देशभागः, मंडलं, ...

Couple, *s.* युग्मं, युगलं, ... युगं, द्वयं, द्वितयं; 'c. of animals' मिथुनं, द्वंद्वं; 'a married c.' वधूवरौ, दंपती, जायापती —*v. t.* संयुज् 7 U, 10, संश्लिष् *c.*, संबन्ध् *c.* (दम्पती) योजयति (D.) —*v. i.* मैथुनं कृ 8 U, क्रीडावशात् संगम् 1 A *or* संमिल् 6 P.

Couplet, *s.* श्लोकः; पंक्तिद्वयं; 'a ... form ed by two verses' युग्मकं

Courage, *s.* धैर्यं, शौर्यं, विक्रमः, पराक्रमः, वीर्यं, उत्साहः, पौरुषं, तेजस् *n.*, ओजस् *n.*, प्रतापः 2 निर्भीकता ... साहसं,

'lose c.' धैर्यहीन a. भू 1 P, सत्त्वात्परिभ्रंश् 1 A, 4 P; '*do not lose c.*' धैर्ये निधेहि हृदये (Mal. 5); 'take c.' आ-समा-श्वस् 2 P; 'summon c.' धैर्यं आलम्ब् 1 A, धैर्यं अवलम्ब् 1 A or अवष्टभ् 9 P, धैर्यावलंबनं कृ 8 U; 'inspire c.' आ-समा-श्वस् c. **-ous,** *a.* शूर, वीर, विक्रांत, धीर. 2 अभीत, धृष्ट, साहसिक (की *f.*). **-ously,** *adv.* सधैर्यं, सविक्रमं, धीर-शूर-वत्. **-ousness,** *See* (*s.*).

Courier, *s.* वार्ताहरः; दूतः, वैवधिकः.

Course, *s.* गति *f.*, प्रसरः, प्र-, क्रमः. 2 रयः, प्रवाहः (of water &c.). 3 मार्गः, पथिन् *m.*, पद्धति (ती) *f.* 4 व्यवहारः, वृत्ति *f.*, आचरणं, चरित्रं. 5 क्रमः, अनुक्रमः, आनुपूर्व्य, परंपरा. 6 रजस् *n.*, पुष्पं, आर्तवं (of women). 7 विधिः, प्रकारः, रीति *f.* ; 'the law must have its c.' यथाशास्त्रमस्य नियोगेन भवितव्यमेव; 'in c. of conversation' कथाप्रसंगेन, कथायोगेन; 'in c. of time' कालक्रमेण, गच्छता कालेन, दिनेषु गच्छत्सु, गच्छति काले; 'a woman in c.' रजस्वला, ऋतुमती, मलिनी, पुष्पवती; 'of c.' अवश्यमेव, नियतं, नूनं, खलु, नाम with एव; 'c. of an arrow' बाणगोचरः, शरपथः; 'c. of study' अध्ययनक्रमः-मार्गः; 'mathematical c.' गणिताध्ययनक्रमः; 'c. of acting' क्रियाविधिः, अनुष्ठानं; 'proper c. of conduct' सुमार्गः; 'there being no other c.' गत्यंतराभावात्; 'having no other c. open,' अनन्यगतिक *a.*; 'race c.' धावनभूमिः; 'in the c. of' मध्ये, अंतरे; 'a house in the c. of erection' निर्मीयमाण भवनं; 'the c. of nature' सृष्टिक्रमः. **-er,** *s.* अश्वः, जविन् *m.*, वारकीरः.

Court, *s.* चत्वरः-रं, अंगनं-णं, प्रांगणं, अजिरं. 2 राजकुलं, राजसभा, आस्थानी-नं (assembly room); राजगृहं-मंदिरं. 3 अनुनयः, अनुवृत्ति *f.*, आराधनं, भजनं, दाक्षिण्यं. 4 (Judge) आधिकरणिकः, प्राड्विवाकः, धर्माधिकारिन् *m.*; (Judges) धर्माध्यक्षाः, प्राड्विवाकाः (pl.) ; 'c. of justice' अधिकरणं, व्यवहारमंडपः, न्याय-धर्म-सभा. 5 राजपरिजनः-परिबर्हः-परिवारः; 'c. favour' राजप्रसादः, राजानुग्रहः; 'c. minion' राजवल्लभः-प्रियः; 'c-yard' अंगनं, चत्वरं, अजिरं, प्रकोष्ठः, प्रांगण, गृहांगणं. *-v. t.* आराध् 10 अनुसृ 1 P, अनुरंज् c., भज् 1 A. 2 याच् 1 A, प्र-अभि-अर्थ् 10 A. 3 विवाहार्थं याच् or सेव् 1 A. **-eous,** *a.* दक्षिण, विनीत, सविनय, सुजन, सप्रश्रय, सानुनय, सभ्य, शिष्टवत्; 'c. words' सूनृता वाणी. **-eously,** *adv.* सप्रश्रयं, दक्षिणतया, सानुनयं, विनयेन. **-esy,** *s.* दाक्षिण्यं, विनयः, प्रश्रयः, सौजन्यं, अनुरोधः, अनुवर्तनं; 'a title of c.' उपचारपदं. 2 प्रणामः, आनंदनं, आमन्त्रणं. **-ier,** *s.* राजभृत्यः, राजवल्लभः, राजसभासद् *m.*, सभिकः, सभ्यः. **-like,** *a.* शिष्ट, शिष्टाचार, सभ्य. **-ly,** *a.* सुजन, शिष्ट, सभ्य, दक्षिण, सुशील. **-ship,** *s.* आराधनं, अनुरंजनं, अनुनयः, प्रसादनं. 2 स्त्र्युपासना, विवाहार्थं प्रार्थना.

Courtezan, *s.* गणिका, वेश्या, पण्यस्त्री, पण्यांगना, वारस्त्री-योषित्; बंधकी, पुंश्चली.

Cousin, *s.* पितृव्यपुत्रः (त्री *f.*), मातुलपुत्रः (त्री *f.*), पितृष्वसेयः (यी *f.*), मातृष्वसेयः (यी *f.*), according to different relations. 2 ज्ञातिः, बांधवः.

Cove, *s.* वंकः, खातं.

Covenant, *s.* समयः, नियमः, संविद् *f.*, पणः. *-v. i. See* **Contract. -er,** *s.* नियमबद्धः, सामयिकः.

Cover, *v. t.* प्र-सम्-आ-च्छद् 10, प्रा-सं-आ-वृ 5 U, स्थग् 10, पिधा 3 U, निगुह् 1 U, व्यवधा 3 U, अवगुंठ् 10. 2 आ-,स्तृ 5 U, स्तॄ 9 U, व्याप् 5 P, आवेष्ट् 1 A or c., नि-आ-चि 5 U ; 'a c. ed path' छन्न-गूढ-पथः. *-s.* आवरणं, आच्छादनं, पुटं, व्यवधानं, वेष्टनं, अवगुंठनं, पिधानं. 2 कोशः-षः, वेष्टनं. 3 प्रावारः, प्रच्छदपटः, आच्छादनवस्त्रं. 4 अप-व्यपदेशः, छद्मन् *n.*, व्याजः, छलं, माया, कपटं ; 'c. of a well' वि(वी)नाहः ; 'c. of a carriage,' रथगोपनं-आवरणं. **-ing,** *s.* आच्छादनं, आवरणं, &c. 2 तिरस्करिणी, व्यवधानं. 3 परिधानं, प्रावारः, वासस् *n.*, आच्छादनवस्त्रं. 4 अंतर्धा, व्यवधा, अंतर्धिः, अपवारणं, तिरोधानं. **-let,** *s.* उत्तरच्छदः, शय्याप्रच्छदपटः.

Covert, *a.* गूढ, प्रच्छन्न, गुप्त ; 'a c. expression' व्यंग्योक्ति *f.* 2 निर्वात. *-s.* गहनं, गह्वरं. 2 संश्रयः, आश्रयस्थानं.

Covet, *v. t.* लुभ् 4 U, गृध् 4 P, स्पृह् 10 (with dat.) ; कम् 10 A, अभिलष् 1, 4 P, अतिमात्रं इष् 6 P. **-ous,** *a.* लुब्ध, लोलुप, गृध्नु, अभिलाषिन्, ईप्सु, अतृप्त, सतृष्ण. 2 (Of wealth) धनलुब्ध, धनार्थिन्, अर्थपर, धनपरायण. **-ously,** *adv.* सलोभं, लोभेन. **-ousness,** *s.* लोभः, लिप्सा, तृष्णा, लालसा, स्पृहा, अभिलाषः, अतिस्पृहा, लौल्यं. 2 धनलोभः, अर्थतृष्णा.

Covey, *s.* पक्षिगणः ; शावकसमूहः.

Covin, *s.* कूटसमयः-संविद् *f.*

Cow, *s.* गो *f.*, धेनु *f.*; माहेयी, सौरभेयी, उस्रा; शृंगिणी, अर्जुनी, रोहिणी ; एकहायनी, द्विहायनी, त्रिहायणी, चतुर्हायणी 'a c. one year old, 2 years old, and so on'; 'barren c.' वशा, वंध्या ; 'mild one' अचंडी, सुकरा ; 'bringing forth many

calves ' बहुसूतिः; परेष्टुका ; ' producing calves every year ' समांसमीना ; ' an excellent c. ' गोमतल्लिका, गोतल्लजः ; ' c. dung ' गोमयः-यं, शकृत् *n.*; ' c. herd ' गोपः, आभीरः, गोपालः ; ' c. house or pen ' व्रजः, गोष्ठं, गोशाला. -*v. t.* भी c., त्रस् c.

Coward, *s.* कापुरुषः, भीरुः, अशूरः, कातरः, क्लीबः, भीतः, शौर्यहीनः ; ' a boasting c. ' गेहेशूरः, गेहेनर्दिन् *m.* **-ice,** *s.* भीरुता, कातर्यं, अपौरुषं, कापुरुषत्वं, अवीर्यं, अविक्रमः क्लीबता. **-ly,** *a.* भीरु, निर्वीर्य, कातर; *See* (*s.*). -*adv.* सकातर्यं, भीरुवत्, कापुरुषवत्.

Cower, *v. i.* अवनतकाय-नतशरीर -*a.* भू 1 P, महीभू, निभृत-अलक्षितं या 2 P or गम् 1 P, कायमवनमय्य गम्.

Cowl, *s.* फणाकृति शिरोवेष्टनं.

Cowrie, *s.* काकिनी-णी, कपर्दिका, वराटकः.

Coxcomb, *s.* दांभिन् *m.*, दांभिकः, आत्माभिमानिन् *m.*, आत्मविकत्थनः, धूर्तः. 2 चूडा, शिखा. **-ry,** *s.* दंभः, आत्माभिमानः, दर्पः, गर्वः.

Coy, *a.* अप्रगल्भ, सलज्ज, लज्जावत्, विनीत, सव्रीड, शालीन. 2 अल्पभाषिन्, मितवाच्. -*v. i.* लज्ज् 6 A, त्रप् 1 A, ह्री 3 P. **-ly,** *adv.* लज्जया, सव्रीडं, सत्रपं, सलज्जं. **-ness,** *s.* लज्जा, व्रीडा, त्रपा; अप्रागल्भ्यं.

Cozen, *v. t.* वंच् 10; *See* **Cheat. -age,** *s.* प्रतारणा, वंचनं ; माया, भ्रमः, मोहः. **-er,** *s.* वंचकः, कितवः, मायिन् *m.*

Crab, *s.* कुलीरः, कर्कटः-टकः.

Crabbed, *a.* कर्कश, परुष, निष्ठुर. 2 वामशील, प्रतीप, दुःशील. 3 विषम, दुर्ज्ञेय, गूढ, निगूढार्थ. **-ness,** *s.* निष्ठुरता, प्रतीपता, वैषम्यं, दुःशीलं.

Crack, *v. t.* भंज् 7 P, खंड् 10, विद् 9 P, 10, स्फुट् c., भिद् 7 P; ' c. a joke ' परिहासं कृ. 2 (अकस्मात्) ध्वन् c., आस्फल् 10, स्वन् c. -*v. i.* स्फुट् 6 P, विदल् 1 P, भंज्-भिद्-दृ pass ; ' a c. ed sound ' अपस्वरः, विस्वरः. 2 विकत्थ् 1 A. 3 महारवेण स्वन्-क्वण्-ध्वन् 1 P, सहसा महारवं कृ 8 U. -*s.* छिद्रं, रंध्रं, संधिः, भंगः. 2 स्फोटनं, भेदनं. 3 विरावः, ध्वनिः, क्वणितं; ' c. brained ' वातुल, उन्मत्त, भ्रांतचित्त.

Crackle, *v. i.* स्वन्-रट् 1 P, पटपटायते (D.). -*s.* स्वनितं, रटितं, पटपटशब्दः.

Cradle, *s.* दोला, प्रेंखा, प्रेंखोलनं ; (शिशु) खट्वा ; ' from the c. ' आशैशवात् ; ' a child in the c. ' स्तनंधयः, शिशुः. 2 (fig.) निवासभूमि *f.*, आवासः. -*v. t.* दोलायां शी c., दोलामारोप्य चल् c.

Craft, *s.* कला, शिल्पं; कौशलं. 2 व्यापारः, वृत्ति *f.*, व्यवसायः. 3 चातुर्यं, कौशलं, नैपुण्यं ; हस्तकौशलं, नैपुण्यं. 4 शाठ्यता, धूर्तता, कौटिल्यं, कपटं. 5 नौः, तरिः ; ' c. s man ' शिल्पिन् *m.*, कारुः, कर्मकारः. **-y,** *a.* धूर्त, शठ, कुटिल, विजिह्म, कितव, कपटिन्. 2 चतुर, विदग्ध. **-ily,** *adv.* छलेन, कैतवं, धूर्ततया ; चतुरं, विदग्धतया.

Crag, *s.* शृंगं, कूटः-टं, शिखरः-रं. **-ged, -gy,** *a* विषम, अत्यसम, शृंगिन्.

Cram, *v. t.* प्रक्षिप् 6 P, बलाद् निविश् c. 2 अतिभोजनेन तृप् c. or संतुष् c. 3 अतिपूर्णं पृ c. or पूर् 10; स्वस्तिवायनमोदकैः कुक्षिं पूरयित्वा (M. 4) ' having c. ed the belly ' &c.; 'c. ed with food ' अतितृप्तः. 4 आकॄ 6 P, निरुध् 7 U, संबाध् 1 A; ' c.-ed with people ' जनाकीर्ण, जनसंकुल-संबाध. 5 (fig.) अर्थहीनं पठ् 1 P.

Cramp, *v. t.* संकुच् 1 P, स्तंभ् 9 P or c, नि-प्रति-रुध् 7 U, संबाध् 1 A. 2 (अंगं) आकृष् 1 P, उद्वेष्ट् c., उपहन् 2 P. 3 कील् 10 ; ' we are much c. ed in this place ' अतीव दुःस्थिता वयमत्र. -*s.* स्तंभः, संकोचः-चनं, निरोधः, संक्षेपः. 2 उद्वेष्टनं, न्यासः, आक्षेपः, गात्रोपघातः ; ' a c. in the calf of the leg ' पिंडिकोद्वेष्टनं. 3 कीलः, लोहपट्टी, बंधनकीलः (c. iron).

Crane, *s.* बकः, कंकः, सारसः ; बलाका, बिसकंठिका (female c.). 2 भारोत्तोलनयंत्रं.

Cranium, *See* **Skull.**

Crank *s.* वक्रमार्गः. 2 वक्रोक्ति *f.*, वक्रभाषितं.

Cranny, *s.* छिद्रं, रंध्रं, संधिः.

Crash, *s.* महाशब्दः, महानिनादः, कोलाहलः, महारवः. -*v. t.* भंज् 7 P, भिद् 7 P, मुष् 9 P, पिष् 7 P. -*v. i.* (परुषरवेण) ध्वन्-स्वन् 1 P, परुषं रु 2 P.

Crass, *a.* स्थूल, घन, असूक्ष्म.

Cratch, *s.* गवादनी, द्रोणि-णी *f.*

Crater, *s.* आग्नेयगिरिमुखं.

Craunch, *v. t.* चर्व् 1 P, संदंश् 1 P.

Cravat, *s.* ग्रैवेयकं, ग्रीवावेष्टनं.

Crave, *v. t.* (सविनयं) याच् 1 A, प्र-अभि-अर्थ् 10 A; ' c. favour ' प्रसद् c., अनुनी. 2 वांछ् 1 P, इष् 6 P, अभिलष् 1, 4 P, लभ् desid. (लिप्सते); *See* **Wish. -ing,** *s.* लालसा, स्पृहा, अभिलाषः, अतिकांक्षा, औत्सुक्यं, उत्कंठा, तृष्णा; ' c. for food ' बुभुक्षा; ' c. for drink ' पिपासा, तृष्णा.

Craven, *s.* (c. hearted) कापुरुषः, भीरुः; *See* **Coward.**

Craw, *s.* पक्षिजठरः, पक्वाशयः.

Crawl, *v. i.* सृप् 1 P, वि-प्र-सं°, उरसा गम् 1 P, मंदगत्या चल् 1 P. -*s.* सृप्ति *f.*; पोतोदरं.

Crayon, *s.* वर्तिका, तूलिका.

Craze, *v. t.* भंज् 7 P, खंड् 10; *See* **Break.** 2 चूर्ण् 10, निष्पिष् 7 P. 3 ज्ञानं हन् 2 P,

वातुलीकृ 8 U, क्षुभ् c., संभ्रम c. (भ्रमयति). **-ed, -Crazy,** *a.* वातुल, बुद्धिविकल, हतज्ञान, उन्मत्त, भ्रांतचित्त. 2 जीर्ण, जर्जर, जर्जरीभूत. **-edness,** *s.* बुद्धिवैकल्यं, वातुलता, उन्मादः, चित्तभ्रमः. 2 जीर्णता.

Creak, *v. i.* कर्कशशब्दं कृ 8 U, चर्चर् स्विद् 2 P or स्वन् 1 P. **-s.** कर्कशशब्दः-ध्वनिः.

Cream, *s.* क्षारः, क्षीरजं, शार्करः-रकः, क्षीरमंडं. 2 उत्तमांशः, सारः-रं, सारांशः. **-v. i.** सारं चंड् 6 P. फेनायते (D.). **-v. t.** सारं अपनी 1 P. **-y,** *a.* सारमय (यी *f.*), सारोपम.

Crease, *s.* वलि *f.*, वस्त्रभंगः पुटचिह्नं.

Create, *v. t.* सृज् 6 P, निर्मा 3 A, जन् c. (जनयति), उत्पद् c., कृ 8 U, विधा 3 U, प्र-सं-क्लृप् c. 2 पदे-अधिकारे-नियुज् 7 A, 10 or अभिषिच् 6 P; 'a thing c. ed' भूतं. **-ion,** *s.* सर्गः, जननं, सृष्टि *f.*, निर्माणं, विधानं, प्रकल्पनं, भावना; 'a c. of the mind' मानसी सृष्टिः, मनःकल्पितं. 2 उत्पन्नं, भूतं. 3 विश्वं, निखिलजगत् *n.*, सृष्टि *f.*, सर्वभूतानि. **-ive,** *a.* जनक, कल्पक, उत्पादक, निर्माणक्षम in comp.; 'c. genius' निर्माणशक्तिः. **-or,** *s.* स्रष्टृ *m.*, निर्मातृ *m.* उत्पादकः, जनकः. 2 ब्रह्मन् *m.*, आत्मभूः, परमेष्ठिन् *m.*, पितामहः, विधातृ *m.*, विश्वसृज् *m.*, धातृ *m.*, प्रजापति *m.*, जगत्कर्तृ *m.*, स्रष्टृ *m.*, विधि *m.*, वेधस् *m.*, स्वयंभूः, चतुराननः, विरिंचि *m.*, कमलयोनि *m.*, अब्जभूः. **-ure,** *s.* भूतं, जंतुः, जीविन्-प्राणिन् *m.*, देहिन् *m.* 2 प्रियः, वत्सः, जातः. 3 आश्रितः, उपजीविन् *m.*, लब्धोदयः; 'he is your c.' स त्वत्तो लब्धोदयः, त्वदुपजीवी.

Credence, *s.* विश्वासः, प्रत्ययः, प्रमाणं; 'worthy of c.' विश्वास्य, प्रमाण; 'to give c.' विश्वस्-प्रती 2 P.

Credentials, *s.* विश्वासपत्रं, प्रत्ययपत्रं.

Credible, *a.* विश्वसनीय, श्रद्धेय, विश्वास्य, प्रामाणिक (की *f.*). **-Credibility,** *s.* विश्वास्यता, विश्वासपात्रता, प्रामाण्यं. **-Credibly,** *adv.* सप्रमाणं, श्रद्धेयतया, विश्वसनीयतया.

Credit, *s.* विश्वासः, प्रत्ययः, विस्रंभः; 'worthy of c.' विश्रंभभाजनं, विश्वासपात्रं. 2 प्रशंसा, श्लाघा, कीर्ति-ख्याति *f.*, प्रतिष्ठा, यशस् *n.*, स्तुति *f.*, स्तवः. 3 (in commerce) विश्वासः; कालिका; 'buying on c.' उद्धारः. 4 प्रामाण्यं, विश्वास्यता. **-v. t.** विश्वस् प्रती 2 P, सत्य *a.* मन् 4 A. 2 प्रमाणीकृ 8 U. **-able,** *a.* श्लाघ्य, प्रशस्य, कीर्ति-गौरवकर (री *f.*), स्तुत्य. **-ably,** *adv.* श्लाघ्यप्रकारेण, स्तुत्यर्हं, सगौरवं. **-or,** *s.* उत्तमर्णः, ऋणदातृ *m.*, धनिकः.

Credulous, *a.* श्रद्धालु, विश्वासशील, विश्वासिन्, विस्रंभपरायण, अशंकित. **-ness, -Credulity,** *s.* विश्वासशीलता, अशंकता, श्रद्धालुता.

Creed, *s.* धर्मः 2 स्वीकृतमतं-पक्षः.

Creek, *s.* वंक्रः, वक्रं, खातं. **-y,** *a.* वंक्रवत्, वक्र.

Creep, *v. i.* सृप् 1 P, वि-सं प्र °, मंदमत्या चल्, मंदं प्रसृ 1 P. 2 अलक्षितं प्रविश् 6 P. 3 शनैः प्लुत् 1 A. **-er,** *s.* लता, वल्ली, वल्लरी, प्रतानिनी *f.*, 'a branching c.' वीरुध् *f.*, गुल्मिनी, उलपः, प्रतानिनी. 2 सर्पिन्-उरोगामिन् *m.* **-ing,** *s.* विसर्पः-र्पणं, विसारः. **-ingly,** *adv.* सर्पवत्, मंदगत्या, शनैः-शनैः.

Cremate, *v. t.* See **Burn.** **-tion.** दाहः, दहनं.

Crepitate. *See* **Crack.**

Crepuscle, -scular, *See* **Evening.**

Crescent, *s.* अर्धचंद्रः, अर्धेंदुः, चंद्रार्धं. **-a.** 'c.-shaped' अर्धचंद्राकार. 2 वर्धमान, वर्धिन्.

Cresset, *s.* आकाशदीपः.

Crest. *s.* चूडा, शिखा, शेखरः, मौलिः; मुकुट, किरीटः. 2 (of a cock) चूडा, शिखा. 3 शिखरः-रं, मूर्धन् *m.* (of mountains); 'c. fallen' भग्न, भग्नदर्प, आत्तमान, विषण्ण; 'c. jewel' चूडामणिः, शिरोरत्नं-मणिः, शिखामणिः. **-ed,** *a.* शिखिन, चूडावत्. 2 अवतंसित किरीटिन्.

Cretaceous, *a.* कठिनीसंसृष्ट, कठिनीधर्मन्.

Crevice, *s.* रंध्रं, छिद्रं, विवरं, बिलं, संधिः. गर्तः-र्तं.

Crew, *s.* नाविकाः, पोतवाहाः (pl.), नाविकगणः. 2 गण., संघः, जनसमूहः.

Crib, *s.* प्रवाहनी, द्रोणि-णी *f.* 2 गोष्ठं, व्रजः. 3 शिशुदोला. **-v. t.** **Confine,** q. v.

Cribble, *s.* चालनी, शोधनी, तितउ *m.*

Crick, *s.* कर्कशशब्दः. 2 मन्यास्तंभः.

Cricket, *s.* झिल्लिका, घुंघारी, झीरुका, चीरी. 2 झुल्लिकाक्रीडा.

Crime, *s.* अपराधः, पापं, दोषः, पातकं, पापकर्मन् *n.*, दुरितं; 'a heinous c.' घोर-महापातकं. **-Criminal,** *a.* or *s.* अपराधिन्, पापिन्, सपाप, पातकिन्, कृतापराध पापकर्मन्, *n.* सदोष, दुष्कृतिन्; दंड्य, दोषग्रस्त; 'c. act' पापक्रिया; 'c law' दंडविधिः-शास्त्रं. **-ly,** *adv.* सापराधं, सदोषं. 2 दंडविधिन्यायेन, दंडविधिवत्. **-ity,** *s.* सपापता, अपराधिता, सदोषत्वं. **-Criminate,** *v. t.* दोषीकृ 8 U, सापराध-सदोष *a.* कृ, दोषेण लिप् 6 P. 2 अभिशंस् 1 P, अभियुज् 7 A, 10. **-ion,** *s.* अभियोगः, दोषीकरणं, दोषारोपणं, अभिशंसनं. **-ory,** *a.* अभिशंसक; सदोष.

Crimp, *a.* भंगुर भिदुर. 2 असंगत, विरुद्ध, अयुक्त. **-v. t.** **-Crimple.** संकुच् 1 P, कुंचीकृ 8 U, चुण् 10.

Crimson, *a.* शोण, रक्त, अरुण, लोहित. *—s.* शोणः, रक्तिमन् *m.*, रक्तवर्णः, अरुणिमन् *m.*, लोहितः; 'covered with c.' अरुणित, पाटलित. *—v. t.* अरुणीकृ 8 U, अरुणयति-शोणयति-लोहितयति (D.).

Crincum, *s.* वलि *f.*, भुग्नः; संकोचः.

Cringe, *v. i.* अंजलिं बंध् 9 P; चरणोपान्ते प्रणम् 1 P or अनुनी 1 P; 'c. at the feet' चरणाग्रपाते कृ 8 U (Bh. i. 31). *—r.*, *—ing,* *s.* अंजलिकर्मन् *n.*, अधोमपातः; अनुवृत्ति *f.* *—v. t.* See **Contract.**

Crinigerous, *a.* रोमवत्, रोमोपम.

Crinkle, *s.* वलि *f.*, भुग्नः, भंगः. *—v. i.* घूर्णीभू 1 P, व्यावृत् 1 A. *—v. t.* घूर्णीकृ 8 U, व्यावृत् c.

Cripple, *a.* or *s.* पंगु (गू *f.*), विकल, विकलांग (गी *f.*): पादविकल; गतिहीन; श्रोण. *—v. t.* विकलयति (D.), विकलीकृ 8 U, भंगीकृ. 2 (fig.) दुर्बलीकृ. *—ness,* *s.* पंगुता, अंगवैकल्यं.

Crisis, *s.* संकटं, संकटवेला, संदेहसमयः; घुणाक्षरन्याय. 2 व्याधिसीमा. **—Critical,** *a.* संदिग्ध, 'c. time' कार्यसंकटे, संकटसमयः, कार्यनिर्वहणकालः; 'at c. times' उपस्थितेषु कृत्येषु.

Crisp, *a.* आकुंचित, वंधुर, भंगवत्. 2 भंगुर, भिदुर, भिदेलिम. *—v. t.* (केशान्) रच् 10, भंगुरीकृ 8 U, आकुंच् c., 'c. ing-iron, -pin' केशाकर्षणकीलः; 'c. ed tresses' घूर्णकुंतलाः, वलीभूताः अलकाः. **—ation, —ature,** *s.* आकुंचनं (केशानां).

Criterion, *s.* लक्षणं, चिह्नं, लिंगं, संज्ञा. 2 निकषः.

Critic, *s.* गुणदोषविचारकः-निरूपकः, गुणागुणज्ञः; विज्ञः, गुणग्राहिन् *m.*, गुणदोषविवेचकः 2 (cavilling c.) दोषैकदृश्-छिद्रान्वेषिन् *m.* **—al,** *a.* गुणदोषविचारक, गुणागुणज्ञ; गुणदोषग्राहिन्, गुणदोषविवेचक. 2 दोषदर्शिन्, छिद्रान्वेषिन्. **—ally,** *adv.* सूक्ष्मं, सूक्ष्मतया, निपुणं. 2 गुणदोषपरीक्षया. 3 संकटसमये. **—ise,** *v. t.* गुणदोषविचारं-विवेचनं कृ 8 U, गुणदोषान् निरूप् 10 or परीक्ष् 1 A or वि-विच् 3, 7 U. 2 छिद्राणि अन्विष् 4 P. or दृश् 1 P. **—ism, Critique,** *s.* गुणागुणपरीक्षा, गुणदोषविवेचनं-परीक्षणं-निरूपणं. 2 छिद्रान्वेषणं.

Croak, *v. i.* आरट् 1 P, विरु 2 P. 2 (As a crow) कै 1 P, ध्वांक्ष् 1 P. *—s.* आरटनं; विरावः, काकरवः.

Croceous, *a.* कुंकुमाभ, गौर (री *f.*).

Crock, *s.* पिठरं, कलशः. 2 भांडं. 3 अरण्यांघी. 4 अवलुंचः. *—v. t.* कुष्णीकृ 8 U, कज्जलेन लिप् 6 P. **—ery,** *s.* मृद्भांडानि (pl.); कौलालकं; मार्त्तिकं.

Crocodile, *s.* नक्रः, कुंभीरः, मकरः, ग्राहः, अवहारः (a kind of c.).

Croft, *s.* वाटिका; वाटः, वृति *f.*

Crone, *s.* स्थविरा, जरती, वृद्धा, जरठा.

Crony, *s.* चिरमित्रं, प्रियमित्रं-सुहृद् *m.*

Crook, *s.* वक्रः; कुंचितयष्टि *f.*; आकर्षणी; 'by hook or c.' येन केन प्रकारेण, यथाकथंचित्; 'c. back' कुब्जः, न्युब्जः, गडुरः. *—v. t.* आकुंच् c., वक्रीकृ 8 U, कुटिलीकृ, नम् c. **—ed,** *a.* वक्र, कुटिल, जिह्म, अराल, नामित, आकुंचित, भुग्न, न्युब्ज; 'c. bodied' विकृताकारः; 'c. armed' कुणि, कु(कू)र्पिः, विकरः; 'c. nature' वक्रभावः, कौटिल्यं; 'c. minded' कुटिलमति, जिह्मचेतस्, प्रतीप, अनृजुप्रकृति; 'c. with age' जरानतकाय, जरापरिणत. **—edly,** *adv.* वक्रं, कुटिलं, कुटिलगत्या, जिह्मं, साचि, तिर्यक्; 'going c.' जिह्मग., कुटिलगतिः. **—edness,** *s.* वक्रता, कुटिलता, जिह्मता. 2 विरूपता, विकृति *f.*

Crop, *s.* शस्यं, शस्यसंग्रहः, कृषिफलं; 'c. s' शस्यक्षेत्राणि 2 अग्र, शिखा. *—v. t.* (शस्यं) चर् 1 P, अद् 2 P, भक्ष् 10, चर्व् 1 P. 2 छिद् 7 P, लू 9 U, शस्यं लू or संग्रह् 9 P. *—v. i.* (up) आविर्भू 1 P, प्रादुर्भू, सहसा उद्भू 1 P, 'c. eared' छिन्नकर्णाग्र, लूनकर्ण; 'c. ful' परिपूर्णोदर, अतितृप्त.

Crore, *s.* कोटि-टी *f.*

Cross, *v. t.* तॄ 1 P, (lit. and fig.), संतॄ°, लंघ्, उत्° 1 A, 10, अति-इ 2 P, अतिक्रम् 1 U. 4 P, आक्रम्; 'these thoughts c. ed my mind' एते संकल्पा मम प्रादुरासन् or आसीन्-मम मृत न नमसि (Ka.); 'he c. ed my sight' मम दर्शनपथमागतः (S. 3), नयनविषयमवतीर्णः. 2 वि-प्रति-रुध् 7 U, व्याहन् 2 U. प्रतिबंध् 9 P. 3 व्यति-अस् 4 U; 'with the arms c. ed' व्यत्यस्तभुजः, स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः (Mal. 4), 'c. legged' व्यत्यस्तपाद्., 'to c. the legs' व्यत्यस्तपादाभ्यां आस् 2 A. 4 (in love) खंड् 10, खंडिता नारी 'c. ed or defeated in love.' *—s.* क्रूश. 2 शूलः-लं. 3 प्रतिरोधः, विघ्नः, प्रत्यूहः, व्याघातः, प्रतिबंधः. 4 न्यस्तरेखाद्वयं, स्वस्तिकचिह्नं, स्वस्तिकं. *—a.* व्यत्यस्त, तिरश्चीन, मार्गस्थित. 2 वि-प्रतिलोम, विरुद्ध, वाम, प्रतीप, प्रतिकूल. 3 दुःशील, विमुख, दुरासद, वक्रस्वभाव, जिह्मप्रकृति, वामशील; 'c. road' उपपथः, उपमार्गः; चतुष्पथं, शृंगाटकं; 'c.-examine' विविधं परीक्ष् 1 A or अनुयुज् 7 A; 'c. grained' प्रतीप, विलोम, विरुद्ध; 'to be c.' प्रतीपं अय् 1 P, प्रतीपायते (D.); 'c. multiplication' वज्राभ्यासः; 'c. threads' पूर्णं. **—ly,** *adv.* तिर्यक्, व्यत्यस्तं, साचि. 2 प्रतीपं,

प्रतिकूलं, विरुद्धं. 3 पिशुनतया. -ness, s. वक्रता, अनृजुता, जिह्मत्वभावः, वैगुण्यं.

Crotch, *s.* अंकुशः, आकर्षणी, बडिशः.

Crotchet, *s.* कामचारः, लहरी, मनोलौल्यं, स्वैरिता.

Crouch, *v. i.* पत् 1 P (पादयोः); पादयोर्लुठ् 4 A, नम्रीभू 1 P, कायं नम् c. 2 चाटूक्त्या अनुनी 1 P or प्रसद् c.; *See* **Cringe.**

Crow, *s.* काकः, वायसः, ध्वांक्षः, मौकुलिः; 'carrion c.' कुणपभुज्, दग्धकाकः; 'c. bar,' लोहदंडः. -*v. i.* विरु 2 P, नद् 1 P. 2 विकत्थ् 1 A; *See* **Boast.**

Crowd, *s.* समूहः, संघः, वृंदं, गणः; *See* **Collection;** 'c. of people' जनसंमर्दः, संकुलं, जनौघः, लोकसंघः, बहुजनमेलकः. -*v. i.* 'to be c. ed' सं-आ-कॄ pass., परिपॄ pass., संकुल-समाकुल-*a.* भू 1 P, 'house c. ed with people' जनाकीर्ण-जनसंकुलं गृहं; 'the place was very much c. ed' तस्मिन् स्थाने महान् जनसंमर्द आसीत्. -*v. t.* आ-सं-कॄ 6 P, परिपॄ *c.* or पूर् 10, व्याप् 5 P, संकुलीकृ 8 U. 2 संमृद् 9 P, संबाध् 1 A, संकुलीकृ.

Crown, *s.* मुकुटं, किरीटः-टं. 2 राज्यं, राजपदं, राजत्वं; 'placed the c. on' राजपदमारोपितः, राज्येऽभिषिक्तः. 3 राजन् *m.*, शासितृ *m.* 4 (Of the head) चूडा, शिखा, मौलिः. 5 अग्रं, शिखा, शिखरं, शीर्षकं, शिरस् *n.* शृंगं, अग्रभागः. 6 स्रज् *f.*, माला. 7 रूप्यमुद्रा -*v. t.* राज्ये अभिषिच् 6 P, मुकुटं परिधा c. (धापयति). 2 संपद् c., समाप् c., निष्पद् c.; 'c.-ed kings' मूर्धावसिक्ताः-मूर्धाभिषिक्ताः-राजानः; 'to c. all' इदं च तत्र विशिष्टतमं जातं; 'to be c. ed' फल् 1 P, सफलीभू; 'his efforts were c. ed with success' सर्वेऽस्य प्रयत्नाः सफलतां ययुः-फलिताः.

Crucial, *a.* सूक्ष्म, निपुण.

Crucible, *s.* मु(मू)षा-षी, तैजसावर्तनी.

Crude, *a.* अपक्व, अपरिणत, असिद्ध, असंस्कृत, आम. 2 अजीर्ण. 3 असंपूर्ण, असमाप्त; अपूर्णकाल, आकालिक (की *f.*); 'c. form' प्रातिपदिकं, असिद्धं, रूपं. -ly, *adv.* अपूर्णकाले. -ness, *s.* अपक्वता, आमता, अपाकः, अपरिणामः.

Cruel, *a.* नृशंस, क्रूर, निष्ठुर, निष्करुण, निर्दय, निर्घृण, कठिनहृदय, क्रूरकर्मन्. -ly, *adv.* निष्करुणं, निर्दयं, निष्ठुरं, &c. -ty, -ness, *s.* नृशंसता, निष्ठुरता, निर्दयत्वं, क्रूरता, निर्घृणता; 'c. to animals' प्राणिहिंसा.

Cruise, *s.* समुद्रे परिभ्रमणं, पर्यटनं. -*v. i.* परिभ्रम् 1, 4 P, इतस्ततो भ्रम्.

Crum, Crumb, *s.* खंडः, लवः, शकलः-लं. 2 उच्छिष्टं, अवशेषः, पिष्टकशकलं. -**Crummy,** *a.* कोमल, मृदु.

Crumble, *v. i.* चूर्णीभू 1 P, भिद् pass., शकलीभू; पत् desid. (पिपतिषति). 2 विनश् 4 P, क्षि pass., अवसद् 1 P. -*v. t.* चूर्ण् 10, क्षुद् 7 U, निष्पिष् 7 P, मृद् 9 P, शकलीकृ 8 U; खंडशो भिद् 10. 2 विनश् c., अवसद् c. -ing, *a.* जीर्ण, अवसन्न, विशीर्ण.

Crump, *a.* कुब्ज, न्युब्ज, वक्र.

Crumple, *v. t.* संकुच् 1 P, संपुट् 10; *See* **Contract.** 2 चूर्ण् 10, संमृद् 9 P.

Crunch, *v. t.* दंतैर्निष्पिष् 7 P.

Crupper, *s.* पुच्छबंधः.

Cruse, *s.* मृद्भांडं.

Cruset, *s.* *See* **Crucible.**

Crush, *v. t.* संमृद् 9 P or c., संपीड् 10, निष्पिष् 7 P, क्षुद् 7 U, मंथ् 9 P, निर्दल् 1 P, 10 चूर्ण् 10; 'c. under the foot' पादतलेन-पादाघातेन-मृद्, पादभरेण आक्रम् 1 U, 4 P. 2 विध्वंस् c., विनश् c, उच्छिद् 7 P. -*s.* मर्दनं, निष्पेषः. 2 जनसंमर्दः, संकुलं. -ing, *a.* प्रमाथिन्; 'c. defeat' सर्वनाशकरः पराजयः.

Crust, *s.* त्वच् *f.*, बाह्यपटलं, वल्कं, बाह्यवेष्टनं. 2 घनभागः, बाह्यभागः. -*v. t.* घनपटलेन वेष्ट् c. or आवृ 5 U or आच्छद् 10, बाह्यतः घनीकृ 8 U. -*v. i.* घनपटलं वेष्ट् 9 P, घनीभू; संहतीभू. -aceous, *a.* कठिन्, वल्कवत्, पटलवत्. -y, *a.* घनपटलयुक्त, सपटल. 2 प्रतीप, परुष, निष्ठुर, पिशुन.

Crutch, *s.* अवलंबनार्थं दंडः; आधारदंडः.

Cry, *v. i.* क्रुश् 1 P, विलप् 1 P, रुद् 2 P, परि-देव् 1 A, 10, बाष्पं मुच्-विसृज् 6 P, or पत् c. 2 (of crows &c.) वाश् 4 A, विरु 2 P; नद् 1 P, रस् 1 P. 3 वि-उद्-घुष् 10, प्रकाश् c., प्रख्या c. (ख्यापयति); 'c. ing in the wilderness' अरण्यरुदितं. 4 तारस्वरेण-उच्चैः वद् 1 P, or भाष् 1 A, आ-वि-क्रुश् 1 P, आ-, क्रंद् 1 P. -*s.* क्रंदनं, रुदितं, रोदनं, आक्रोशः, विलापः, परिदेवनं. 2 ध्वनिः, स्वनः, स्वरः, शब्दः, नादः; 'c. of distress' आर्तनादः, करुणस्वनः; रुतं, विरावः; (gen. of animals). 3 उत्क्रोशः, घोषणं, उच्चैर्घोषः, कोलाहलः. -down, अपवद् 1 P, अवगण् 10, अवमन् 4 A, अपलप्. -out, उत्क्रुश्, उच्चैः-तारस्वरेण-घुष्. -up, प्रशंस् 1 P, कृत् 10. -er, *s.* घोषकः, प्रकाशकः, घोषणाकृत् *m.*

Crypt, *s.* गुहागृहं.

Crystal, *s.* स्फटिकः, सितोपलः, सितमणिः, स्फटिकाश्मन् *m.* -*a.* 'c. like' स्फटिकाभ, विमल, स्वच्छ. -ize, *v. t.* स्फटिकरूपेण घनीकृ 8 U or घनीभू.

Cub, *s.* शावः-वकः, पोतः, कलभः, वत्सः, शिशुः, किशोरः-रकः.

Cube, *s.* घनः; 'c. root' घनमूलं, घनपदं. -**Cubical,** *a.* घनाकार; 'c. contents' घनफलं

Cubit, *s.* हस्तः, किष्कुः; अरत्नि *m.*, *f.* (with the last finger stretched).

Cuckold, *s.* बंधकीभार्यः; जारिणीपतिः and sim. comp.; 'c. maker' *See* **Adulterer.**

Cuckoo, *s.* कोकिलः, पिकः, परभृतः, पुंस्कोकिलः (male c.); 'female c.' अन्य-परपुष्टा or भृता, कोकिला.

Cucumber, *s.* चर्मटिका, चर्भटः, कर्कटी, उर्वारु *f.*, इ(ई)र्वारु-रु *f.*

Cud, *s.* चर्व्यः, आहारः.

Cuddle, *v. i.* अंके-निकटे स्वप् 2 P or शी 2 A.

Cudgel, *s.* लगुडः, यष्टि *f.*, दंडः, काष्ठं, गदा; 'c.-play' गदायुद्धं, दंडादंडि. -*v. t.* लगुडेन प्रहृ 1 P or आहन् 2 U or तड् 10; 'giving a sound c. ing' लगुडप्रहारैः जर्जरीकृत्य; 'c. your memory' स्मृतिं प्रबोधय तावत्.

Cue, *s.* संज्ञा, इंगितं, सूचना; सूत्रं. 2 अंचलः. 3 छंदः, भावः.

Cuff, *s.* मुष्टिप्रहारः, मुष्ट्याघातः. 2 पिप्पलांचलः. -*v. t.* मुष्टिना-पाणिना-तड् 10 or प्रहृ 1 P or आहन् 2 U; मुष्टीमुष्टि युध् 4 A.

Cuirass, *s.* कवचः-चं, उरस्त्राणं. 2 कूर्पासः; निचोलकः.

Cuish, *s.* ऊरुत्राणं, ऊरुवर्मन् *n.*

Cuisine, *s.* पाकशाला, पाकपद्धति *f.*

Culinary, *a.* पाक in comp.; 'c. skill' पाकसिद्धिज्ञानं.

Cull, *v. t.* उद्धृ 1 P, वृ 5 U; संमा-हृ; एकत्र कृ 8 U; 'c. passages' चूर्णिकां कृ.

Cullion, *s.* जाल्मः, धूर्तः, शठः.

Cully, *s.* वेश्याजितः, सुखप्रतार्यः.

Culm, *s.* नालं, कांडं.

Culminate, *v. i.* उच्चस्थानं प्राप् 5 P; 'the sun is c. ing' नभसो मध्यमध्यास्ते रविः; (fig.) परां कोटिं-काष्ठां-गम् 1 P, अतिभूमिं गम्; पाताभिमुखीभू, क्षयिष्णु *a.* भू. -ion, *s.* परा कोटिः, परा काष्ठा.

Culpable, *a.* सदोष, सापराध, निंदार्ह, दोषिन्, अपराद्ध, वाच्य, निंद्य, दूषणीय. -ness, **Culpability,** *s.* सदोषता, अपराधिता, वाच्यता.

Culprit, *s. See* **Criminal.**

Cult, *s. See* **Creed.**

Cultivate, *v. t.* कृष् 1 P, (land &c.) 2 कृष् c., उप-प्र-चि 5 U, परि-अनु-शील् 10, अभ्यस् 4 P, आसेव् 1 A, अनुष्ठा 1 P, भज् 1 U; 'c. friendship with the good' सतां मैत्रीं प्रचिनु-अभ्यस्य. -ion, **Culture,** *s.* कृषि *f.*, कर्षणं, कृषिकर्मन् *n.* 2 अनुशीलनं, अभिवृद्धि *f.*, संवर्धनं, प्रबोधनं. 3 उन्नति *f.*, उत्कर्षः; 'c. of the mind' प्रबोधः, मनःसंस्कारः; 'men of c.' प्रबुद्धमनस्काः-संस्कारवंतः-जनाः, सुजनाः, 'c. of learning' विद्याभिवृद्धिः, ज्ञानोन्नतिः, &c. -or, *s.* कृषीवलः, कर्षकः, क्षेत्रिन् *m.* 2 अनुष्ठातृ *m.* परिशीलितृ *m*, संवर्धकः.

Culver, *See* **Dove.**

Culvert, *s.* प्रच्छन्नः जल-प्रवाहः-निर्गमः.

Cumber, *v. t.* बाध् 1 A, क्लिश् 9 P; कष्ट-दुःखं-आवह् 1 P, अतिभारो भू 1 P. -*s.* क्लेशः, कंटकः, शल्यं, अतिभारः. -some, **Cumbrous,** *s.* कष्ट-दुःख-कर (री *f.*), क्लेशप्रद, अतिभारभूत. -**Cumbrance,** *s.* अतिभारः, शल्यभूतः, भारभूतः. 2 उपरोधः, प्रतिबंधः, प्रत्यूहः.

Cumin, *s.* जीरकः, जरणः, कणा, अजाजी; 'black c.' सुषवी, कारवी, पृथ्वी; पृथुः, काला, उपकुंचिका.

Cumulate, *See* **Accumulate.**

Cunning, *a.* विदग्ध, धूर्त, चतुर. 2 मायिन्, वंचनशील, विप्रलंभक, कपटिन्. -*s.* विदग्धता, धूर्तता, चातुर्य, नैपुण्यं, पटुता. 2 कपटं, माया, वंचनं, शाठ्यं, व्याजः, कैतवं, छलं. -ly, *adv.* चातुर्येण, विदग्धतया, धूर्ततया, सव्याजं.

Cup, *s.* पात्रं, चषकः-कं, भाजनं, काचपात्रं. 2 पुटः, कोशः-षः; 'fond of the c.' पानासक्तः; 'taste the c. of misery,' दुःखभाग् भू. -*v. i.* आचूषण-यंत्रेण रक्तं मुच् c. or मोक्ष् 10; 'c.-board' लघुकोष्ठः; 'c. -ing glass' रक्तचूषणयंत्रं, 'dry c.-ing' घटिकया or अलाब्वा आचूषणं.

Cupid, *s.* मदनः, स्मरः, कामः, अनंगः, कंदर्पः, मन्मथः, मनसिजः, कुसुमबाणः, पंचशरः, मारः, प्रद्युम्नः, मीनकेतनः, कुसुमेषुः, मकरध्वजः, पुष्पधन्वा, आत्मभूः, अनन्यजः, चित्तजन्मन् and sim. comp. -ity, *s.* लोभः, गृध्नुता, अतिलोभः-स्पृहा, लालसा, अतितृष्णा, लाभलिप्सा. 2 कामुकता.

Cupola, *s.* तोरणशृंगं, प्रासादशीर्षं.

Cur, *s.* शुनकः; *See* **Dog.** -rish, *a.* शील, दुष्ट.

Curate, *s.* उपयाजकः, पुरोहितप्रतिनिधिः.

Curator, *s.* अवेक्षकः, अधिकारिन् *m.*, अध्यक्षः; 'c. of a depot' ग्रंथशालाधिकारी.

Curb, *v. t.* आवृ 5 U, सं-नि-यम् 1 P, नियंत्र् 10, प्र-नि-ग्रह् 9 P, अव-नि-रुध् 7 U. संह् 1 P; 'c. the horses' प्रगृहीतां वाजिनः (S. 1); *See* **Control** also. -*s.* मुखयंत्रणं, मुखशृंखला-लः. 2 यंत्रणं, संयमः, निरोधः, &c.

Curd, *v. i.* दधिरूपेण घनीभू, स्त्यै 1 A. -*v. t.* घनीकृ 8 U, स्त्यै c., संहन् 2 P. -*s.* दधि *n.*; पयस्यं, प्रस्तः-सं. -y, *a.* दधिमय (यी *f.*). 2 घनीभूत, स्त्यान, संहत.

Curdle, *v. i. See* **Curd, -ed,** *See* **Curdy.**

Cure, *v. t.* (disease) कित् desid. (चिकित्सति-ते), प्र-उप-शम् c. (शमयति), साध् c., प्रतिकृ 8 U, समाधा 3 U. (persons) सुस्थ-प्रकृतिस्थ-नीरोग *a.* कृ ; gen. ex. by. निर्-गत-वीत in comp.; ' Rama was c. ed of his fever ' रामो ज्वरोपशमनान्नीरोगः कृतः, प्रकृतिस्थः संजातः; ' c. ed of wounds ' निर्व्रणः कृतः; निर्विषः; &c. **-s.** चिकित्सा, उपशमः, प्रति(ती)कारः, रोगोपशमः. **2** सुस्थता, स्वास्थ्यं. **3** भेषजं औषधं. **-able,** *a.* साध्य; ' inc. by physicians ' भिषजामसाध्यं (R. VIII. 93); शमनीय, प्रतिकार्य. **-ative,** *a.* रोगहर, रोगघ्न (घ्नी *f.*), व्याधिशमक, शांतिद. **-er,** *s.* चिकित्सकः, **-less,** *a.* असाध्य, दुरुपचार.

Curiosity, *s.* कुतूहलं, कौतूहलं, जिज्ञासा, कौतुकं, कुतुकं; oft. ex. by desid. nouns; ' c. to see ' दिदृक्षा. **2** (Object of c.) अपूर्ववस्तु *n.* दुर्लभद्रव्यं, उत्कृष्टद्रव्यं. **-Curious,** *a.* कुतूहलिन्, जिज्ञासु, कौतुकाक्रांतचित्त, कुतुकाविष्ट, सकौतुक; ' my heart is c. to know ' जिज्ञासाक्रांतहृदयोस्मि, oft. by desid. ; 'c. to ascertain' उपलिप्सुः. **2** अपूर्व, अदृष्टपूर्व, अद्भुत, चित्र, दुष्प्राप, दुर्लभ; दुर्लभीय. **3** सूक्ष्म, विज्ञ; निपुण, विचक्षण, सूक्ष्मदर्शिन्. **-ly,** *adv.* कुतूहलेन; सूक्ष्मं, अद्भुतं, चित्रं.

Curl, *s.* चूर्णकुंतलः, अलकः, कुरलः; ' hair thick with c s. ' कुंतलाकीर्णाः शिरोरुहाः. **2** तरंगः, ऊर्मि *f.* **-v.** *t.* (केशान्) आकुंच् c. व्यावृत् c., रच् 10. **2** तरंगयति (D) **-v.** *i.* जिम्हीभू, वक्रीभू, आकुंच् pass., व्यावृत् 1A. **2** तरंगायते (D). **-ed, -ing,** *a.* कुटिल, अराल, कुंचित; ' c. mass of smoke ' धूमस्पोत्पीडः (U. 3).

Curmudgeon, *See* **Miser.**

Currant, *s.* शुष्कद्राक्षं.

Current, *a.* प्रचलित, प्रचल, सर्वसंमत; ' languages c. in India ' भरतखंडे प्रचलिता भाषाः. **2** वर्तमान, विद्यमान; 'c. year' वर्तमानसंवत्सरः; ' c. report ' जनप्रवादः; ' c. moment' आपातः. आपातरम्या विषयाः (KI. XI. 12). **3** सर्वसाधारण लोकप्रसिद्ध-विश्रुत, **-s.** स्रोतस् *n.*, प्रवाहः, रयः, वेगः, धारा. ओघः; ' c. of opinion ' साधारणमतौघः. **-ly,** *adv.* साधारणतः, सामान्यतः, लौकिकतया; ' c. known ' लोकप्रसिद्ध. **-Currency,** *s.* प्रचलनं, प्रचारः, प्रसरणं; ' to gain c. ' प्रचलित *a.* भू, प्रसृ 1 P. ' c. pass., ' सर्वसंमत *a.* भू; ' a report gained c. इति जनप्रवादः प्रवृत्तः **2** प्रवाहः, प्रसरः, **3** सुखोच्चार्यता. **4** प्रचलित मुद्रा.

Curriculum, *s.* अध्ययनक्रमः-मार्गः.

Currier, *s.* चर्मकारः, पादूकृत् *m.*

Curry, *v. t.* (favour) अतिचाटूक्त्या प्रसादं संपद् c. or आराध् 10. **2** (a horse) अश्वदेहं मृज् 2 P. **3** (leather) परिष्कृ 8 U, क्षुभ् c. **4** **Beat,** q. v.; ' c. comb ' अश्वदेहमार्जनी.

Curse, *v. t.* शप् 1 U, अभिशंस् 1 P, शापं दा 3 U (with dat.), आक्रुश् 1 P ; गर्ह् 1, 10 A. **-s.** शापः, अभिशापः, आक्रोशः. **2** कंटकः, आधिः ; 'a c. to the family ' कुलस्याधिः, कुलांगारः. कुलपांसुलः ; ' a c. on thy folly ' धिक् त्वां मूढ. **-ed,** *a.* शप्त, आक्रुष्ट; *See* **Accursed.**

Cursory, *a.* क्षिप्र, अत्वरित, त्वरित, अनिपुण, अनवहित, स्थूल ; ' even at a c. glance ' स्थूलदृष्ट्यापि. **-ly,** *adv.* शीघ्रं, स्थूलदृष्ट्या, अनिपुणं.

Curt, *a.* ह्रस्व, संक्षिप्त. **-ly,** *adv.* संक्षेपेण. **-ness,** *s.* संक्षेपः, संहारः, संक्षिप्तता.

Curtail, *v. t.* ह्रस् c., संक्षिप् 6 P; संहृ 1 P; अवच्छिद् 7 P, अल्पीकृ 8 U.

Curtain, *s.* ज(य)वनिका, तिरस्करिणी, व्यवधानं, आवरणपटः; 'behind the c. ' नेपथ्ये; ' c. lecture ' शय्यानुशासनं; 'bed c. ' मशहरी, मशकहरी. **-v.** *t.* आवरणेन प्रच्छद् 10, व्यवधा 3 U.

Curtsy } *See* **Courtesy** under
Curtsey } **Court.**

Curve, *v. t.* नम् c., अव-आ-नम् c., आकुंच् c., वक्रीकृ 8 U, कुटिलीकृ, आवृज् 10. **-s.** नति *f.*, आवर्जनं, वक्रता, आकुंचनं, अंचनं. **2** वक्ररेखा. **-a.** आनत, वक्र, कुटिल, आभुग्न, जिम्ह; *See* **Crooked. -ated,** *a.* आभुग्न, वक्र &c. **-ation,** *s.* आकुंचनं, आवर्जनं, वक्रीकरणं. **-ature,** *s.* वक्रता, वक्रिमन् *m.*, कुटिलता, आनति *f.* वक्रीभावः.

Curvet, *v. i.* प्लु 1 A, वल्ग् 1 P. **-s.** प्लुतं, वल्गनं.

Cushion, *s.* उपधानं, उपबर्हः, पीठोपधानं.

Cusp, *s.* अर्धचंद्रशिखा, अर्धचंद्राग्रं. **-ated,** *a* सूच्यग्र, निशिताग्र.

Custody, *s.* रक्षा, अवेक्षणं, रक्षणं, पालनं, गुप्ति *f.*; *See* **Charge. 2** निरोधः, बंधनं, कारानिरोधः, आसेधः.

Custom, *s.* आचारः, संप्रदायः, व्यवहारः. रीति *f.*, अनुसारः, क्रमः. रूढिः, शुल्कं, राजस्व; ' c. house ' शुल्कस्थानं; ' the officer of c. s ' शौल्किकः. **-ary,** *a.* आचारिक-व्यावहारिक (की *f.*), प्रचलित, लोकसिद्ध, लौकिक (की *f.*); gen. by आचार in comp.; ' to take flowers as is c.' आचारपुष्पग्रहणार्थं (M. 4); आचारलाजाः; &c. **-arily,** *adv.* यथाव्यवहारं,

संबद्धापाकृतारोप, मायकः, वचनार्थे. -er, s. ग्राहकः, केतृ m., निस्त्रकाथिन् m.

Cut, *v. t.* लू 9 U, छिद् 7 P, कृत् 6 P, दो 4 P, वृश्च् 6 P, छो 4 P, 2 भिद् 7 U; खंड् 10; 'c. ing to the quick' मर्मच्छिद्-भिद् मर्माणि कृंतत्; 'c. a hole through,' व्यध् 4 P, नि-भिद्, समुत्कृ 6 P; 'c. a figure' गर्हित-कीर्ति-लभ् 1 A; 'c. short' संहृ 1 P, संक्षिप् 6 P; न्यूनीकृ 8 U; 'to c. the matter short' किंबहुना; 'c. ing short my speech' मद्वचनमाक्षिप्य; 'c. to, or in, pieces' खंडशः-लवशः-छिद्. -*v. i.* उच्छिद् pass., उत्पद् 4 A, स्फुट् 6 P. -*s.* छेदः, प्रहारः, आघातः. 2 कुल्या, खातं. 3 खंडः-डं, भागः, दलं, लवः, लेशः. 4 सरलमार्गः, अविमार्गः. 5 रीति *f.*, रूपं, मार्गः, पद्धति *f.* 'c.-purse' ग्रंथिभेदकः चोरः; 'c.-throat' कंठच्छेदकः; प्राणघातकः, घातकः; (*a.*) मारात्मक, वधोद्यत. -down, अवच्छिद्, कर्तित्वा निपत् c. -off, निकृत्, व्यवच्छिद्. 2 उच्छिद्, उन्मूल् 10. विनश् c. 3 विलुप् c., अपनी 1 P, 4 विच्छिद्, अव-नि-रुध् 7 U, खंड् 10, निवारि 10. -out, उत्कृत् c. 2 परि-सं-कल्प् c. (मनसा); निरूप् 10, चिंत् 10, युज् 10. 3 अतिक्रम् 1 U, 4 P, अतिशी 2 A; *See* **Excel.** -ter, *s.* छेदकः, छेत्तृ *m.*, छिद् in comp.; 'wood-c.' काष्ठच्छिद्. -ting, *s.* छेदनं, कर्तनं, &c. 2 खंडः-डं, शकलः-लं, दलं. -*a.* तीव्र. तीक्ष्ण, मर्मभेदिन्, मर्मस्पृश्-छिद्, अरुंतुद.

Cutaneous, *a.* त्वाच (-ची *f.*), त्वक्संबंधिन्, त्वच् in comp.; 'c. disease' त्वग्रोगः.

Cuticle, *s.* बाह्यत्वच् *f.*, बाह्यचर्मन् *n.*

Cutlass, *s.* खड्गः; कृपाणी.

Cutler, *s.* छुरिकाकारः, शस्त्रकारः.

Cycle, *s.* चक्रं, आ-परि-वृत्ति *f.*, पर्यायः; कालचक्रं.

Cyclone, *s.* चक्रवातः, वातावर्तः.

Cyclops(æ)dia, *s.* *See* **Encyclopædia.**

Cygnet, *s.* हंसशावकः, बालहंसः.

Cylinder, *s.* गोलः, वर्तुलं. -**Cylindrical,** *a.* वर्तुल, गोलाकार.

Cymbal, *s.* झल्लकं, झल्लरी.

Cynic, *s.* मनुष्यद्वेषिन् *m.* -al, *a.* सदावक्र, कुटिलशील, दुरात्मन्, वक्रभाव, निंदाशील.

Cynosure, *s.* ध्रुवः; ज्योतीरथः.

D

Dab, *v. t.* सिक्तवस्त्रेण लघु तड् 10. -*s.* लघ्वाघातः, सेचकः. 2 लघुपिंडः. 3 सिक्तपंकः.

Dabble, *v. t.* सिच् 6 P, प्रोक्ष् 1 P, लिप् 6 P. -*v. i.* जले-पंके-क्रीड् 1 P; 'd. ing in books' पल्लवग्राहि पांडित्यं (H. 1), शास्त्रचुंबनं. -er, *s.* जलक्रीडः; शास्त्रचुंबकः.

Dacoit, *s.* दस्यु *m.* -y, *s.* दस्युकर्मन् *n.*

Dagger, *s.* कृपाणः, छुरिका, कर्तरी, असिपुत्रिका; 'at d. s drawn' सद्यःवद्धवैर *a.*

Daggle, *v. t.* मलेन दुष् c. (दूषयति), पंकेन लिप् 6 P.

Daily, *See* under **Day.**

Dainty, *a.* स्वादु, रुचिर, सुरस, मिष्ट. 2 ललित, कोमल, मृदु, सूक्ष्म. 3 अतिविनीत, अतिसभ्य. -*s.* मिष्ट-विशिष्ट-भोजनं, स्वाद्वन्नं, भोजनविशेषः. -ly, *adv.* स्वादुतया, ललितं, कोमलं. -ness, *s.* स्वादुता; कोमलता, लालित्यं, विलासः, विभ्रमः.

Dairy, *s.* दुग्धशाला, दधिमंथनगृहं; 'd. maid' गोपकन्या, आभीरी, गोदोहिनी.

Dais, *s.* सवितानं उच्चासनं.

Dale, *s.* दरी, कंदरः; उपत्यका.

Dally, *v. i.* विलस् 1 P, विभ्रम् 1, 4 P, क्रीड् 1 P, रम् 1 A. विहृ 1 P. 2 **Delay,** q. v. -ance, *s.* विलासः, विभ्रमः, क्रीडा, विहारः, कामचेष्टा.

Dam, *s.* सेतुः, जलावरणं, धरणः. 2 (पशूनां) मातृ *f.*, जननी अंबा, प्रसूः. -*v. t.* (up) (सेतुना) जलं निरुध् 7 U or संस्तंभ् 9 P.

Damage, *s.* हानि *f.*, अपकारः, अपायः, नाशः, ध्वंसः. 2 (of things in use) क्षयः, क्षति *f.*, उपक्षयः, अपचयः. 3 निष्कृति *f.*, प्रतिफलं, क्षतिपूरणं. -*v. t.* नि-अप-कृ 8 U, क्षि c., नश् c., दुष् c. (दूषयति). 2 हिंस् 7 P, क्षण् 8 P.

Damask, *s.* चित्रदुकूलं. -*v. t.* **Variegate,** q. v.

Dame, *s.* आर्या, भवती (in addressing). 2 स्त्री, गृहिणी, 'old d.' वृद्धा स्त्री, पुरंध्री.

Damn, *v. t.* दंड् 10; *See* **Condemn.** 2 नरकदंडं आदिश् 6 P, नरके निपत् c. 3 गर्ह् 1, 10 A; *See* **Censure.** -able, *a.* गर्ह्य, निंद्य. 2 नरकदंडार्ह. -ation, *s.* नित्य-नरक-वासः; नरकदंडः, नरकयातना, विनिपातः, अनंतदंडः-यातना.

Damp, *s.* क्लिन्न, स्तिमित, आर्द्र, जलासिक्त, उन्न; 'to be d.' क्लिद्, 4 P. 2 विषण्ण, म्लान, अवसन्न, भग्नोत्साह. -*s.* क्लेदः, जलावसेकः, स्तेमः. 2 बाष्पः, धूमः. 3 विषादः, म्लानता, उत्साहभंगः. -*v. t.* क्लिद् c., उंद् 7 P. आर्द्रीकृ 8 U. 2 भंज् 7 P, खंड् 10, दम् c.. भग्नाश *a.* कृ. भग्न-उत्साह-कृ. 'do

not d. his energy' तस्योत्साहभंगं मा कृथाः; 'd. ed by defeat' पराजयेन भग्नोत्साहः. -ish, a. आर्द्रिल, ईषदार्द्र. -ness, s. आर्द्रता, क्लिन्नता.

Damsel, s. कन्या, बाला, कुमारी, बालिका, युवति (ती) f. 'd.'s child' कानीनः (नी f.); 'celestial d.' अप्सरस् f., स्वर्गस्त्री-योषित् f.

Dance, v. i. नृत् 4 P, नट् 1 P; 'who always d. s attendance' यः अहर्निशमुपरचितांजलिः (अधिदेवतमिव) स्तौति (Ka. 109), or merely सांजलि उपस्था 1 A or उपास् 2 A. -v. t. नृत् c., संचल् c. -s. नृत्यं, लास्यं, तांडवं, नाट्यं, पादन्यासः. -er, s. नटः, नर्तकः, कुशीलवः, शैलूषः; 'male d. in a female dress' भ्रु (भ्रू or भ्रू) कुंसः (शः). -ing, s. नाट्यं, नृत्यं; 'd. girl' नर्तकी, 'd. house-school' नृत्यशाला; 'd. master' नाट्याचार्यः.

Dandle, v. t. अंके निधाय लल् 10.

Dandri(u)ff, s. मज्जा ; दारुणं.

Dandy, s. सुवसनः, सुभगंमन्यः ; दांभिकः

Danger, s. भयं, भीति, f., शंका, संदेहः, संशयः. 2 आपद्-विपद् f., अपायः, अनर्थः, व्यसनं, संकटं, दुर्गं, कृच्छ्रं, कष्टः-ष्टं; 'd. to life' जीवितसंशयः; 'the hour of d.' आपत्समयः; 'money is in d. of being lost' द्रव्यापहरणस्य भयं वर्तते; 'without any d.' अकुतोभय a.; 'brought into d.' संशयित; 'attended with d.' संदिग्ध, संशयदोलारूढ. -v. t. संशये पत् c., संशयस्थ a. कृ 8 U. -ous, a. संकट, संबाध, विषम. 2 भयावह, भयंकर, भीतिमद्, भयहेतुक; oft by (s.) in comp. 3 संदिग्ध, शंकाक्रांत, संशयापन्न, विपज्जनक; 'a d. man' अविश्वास्यः, घातुकः. -ously, adv. भयपूर्वकं; 'my brother is d. ill' मम भ्राता जीवितसंशये वर्तते.

Dangle, v. i. दुल् 1 P, लुट् 6 P, चंच् 1 P, लंब् 1 A; 'd-ing at the feet' पादलग्न, चरणलोल.

Dank, a. *See* **Damp.**

Dapple, v. t. चित्र् 10, कर्बुरीकृ, 8 U, कल्माषयति (D.). -ed, a. चित्र, कर्बुर, कल्माषित, शबल.

Dare, v. i. धृष् 5 P, उत्सह् 1 A; साहसं कृ 8 U, शक् 5 P. -v. t. आह्वे 1 A, धृष् c. -s. आह्वानं, योधसंरावः. -ing, s. साहसं, धार्ष्ट्यं, धैर्यं, प्रगल्भता, निर्भीकता. -a. साहसिक (की f.), निर्विशंक, धृष्ट, शूर, प्रगल्भ, निर्भय. -ingly, adv. धृष्टं, साहसेन; प्रगल्भं, निर्भयं. -ingness, s. साहसं, धृष्टता, &c.

Dark, a. अंधकारमय (यी f.), तिमिरावृत, तमोवृत, तामस), तमस्विन्, निष्प्रभ, सतिमिर, सांधकार. 2 कृष्ण, श्याम, नील. 3 अस्पष्ट, गूढ, दुर्बोध. 4 पाप, दुष्ट, खल, मर्षा, मिथ; 'd. in soul तमोवृत्ति, पापात्मन्; 'd. thoughts' पापसंकल्पाः. s., -ness, s. अंधकारः, तमस् n., तमिस्रा-स्रं, ध्वांतं, तिमिरं; 'quality of (tendency to) d.' तमोगुणः; 'slight d.' अवतमसं; 'pitchy (blinding) d.' अंधतमः, सूचिभेद्यं तमः; 'in the d.' रजनीतिमिरे; 'all-pervading d.' संतमसं. 2 गूढं; रहस्यं; 'I am still in the d. about the matter' तस्यार्थस्याहमद्याप्यनभिज्ञः, न किमपि वेद्मि. -en, v. t. अंधकारयति (D.), तिमिरेण आवृ 5 U, तिमिरेण आच्छद् 10. 2 (fig.) कलुषयति-कलंकयति (D.), दुष् c. (दूषयति); 'face d. ed with fury' कोपकलुषिताननं. -v. i. अंधीभू 1 P. -ish, a. ईषत्कृष्ण, आनील. -ly, adv. सांधकारं, अस्पष्टं, अव्यक्तं, गूढं. -some, a. निष्प्रभ, तमोवृत.

Darling, a. प्रिय, प्रियतम, दयित; ex. by जात, तात. -s. स्नेहपात्रं, वत्सः, जातः, दयितः.

Darn, s. वस्त्रसंधिः. -v. t. जीर्णवस्त्राणि सिव् 4 P, or संधा 3 U

Dart, s. अस्त्रं, शल्यं, शंकुः. 2 बाणः; *See* **Arrow.** -v. t. मुच्-क्षिप् 6 P, अस् 4 P, पत् c., विसृज् 6 P, (with loc.). -v. i. जवेन-सहसा-सवेगं-उत्था 1 P, or पलाय् 1 A. 2 सहसा उद्वि 2 P or आविर्भू 1 P. 3 स्फुर् 6 P, विलस् 1 P; 'd. on' रभसा-जवेन प्रचल् 1 P or आपत् 1 P or अभिद्रु 1 P.

Dash, v. t. रभसा प्रक्षिप् 6 P or पत् c., आभत्या-हन् 2 U; 'd. ed her head against a rock' प्रस्तरे तस्याः शिरः आजघ्ने. 2 भंज् 9 P, प्रभंज् 7 P, खंडशः कृ 8 U, चूर्ण् 10, छिद् 10; 'the ship was d. ed to pieces' पोतः खंडशो भग्नः,-सहस्रधा विदीर्णः,-(प्रतिघातेन) शकलीकृतः. 3 अवकृ 6 P; उक्ष् 1 P, सिच् 6 P. 4 संमिश्र् 10. 5 विनश् c., व्यामुह् 2 P or c., विलुप् c. -v. i. (against) आपत् 1 P, आ-समा-हन्. 2 शकलीभू 1 P, विद्-प्रभंज् pass.; 'd. off' जवेन पलाय् 1 A or अपसृ 1 P. -s. संघट्टः, समाघातः, अभिघातः, निष्पेषः, संमर्दः. 2 प्रहारः, आघातः, आक्रमः. 3 प्रागल्भ्यं, धीरता, उत्साहः.

Dastard, -ly, *See* **Coward,-ly.**

Data, s. स्वीकृतानि तत्त्वानि; उपन्यासः.

Date, s. खर्जूरः-री. 2 कालः, तिथि m. f.; कालावधिः, लेखनदिवसः-तिथिः-दिनं; 'out of d.' व्यवहारातिक्रांत. -v. t. तिथिं लिख् 6 P. -v. i. (from) आरभ् 1 A (with abl.); विशिष्टकालादारभ्य प्रवृत् 1 A.

Daub, *v. t.* लिप् 6 P, अंज् 7 P, दिह् 2 U. —*s.* लेपः, विलेपनं. **2** कुचित्रं, कद्वालेख्यं. **–er,** *s.* लेपकः. **2** अकुशलचित्रकारः. **–y,** *a.* श्यान, सांद्र.

Daughter, *s.* कन्या, दुहितृ *f.*, तनया, पुत्रिका, आत्मजा, सुता, पुत्री, नंदिनी; oft ex. by Patronymics; 'd. of Parvata' पार्वती; 'd. of Janaka' जानकी; 'd.-in-law' स्नुषा, वधूः.

Daunt, *v. t.* त्रस् c., भी c., उत्साहं-धैर्यं-भंज् 7 P, भग्नाश *a.* कृ 8 U, धैर्यं स्खल् c. **–less,** (und.-ed), *a.* निर्भीक, निर्भय, अजातशंक, अभीत, अस्खलितधैर्य. **–lessness,** *s.* अभयं, विशंकता.

Daw, *s.* द्रोणकाकः.

Dawdle, *v.* विलंब् 1 A; कालं ह् 1 P or क्षिप् 6 P.

Dawn, *s.* उषस् *f.*, *n.*, प्रत्यूषः, प्रभातं, विभातं, दिनमुखं, अरुणोदयः; 'it is d.' प्रभाता रजनी. **2** उदयः; 'd. of liberty' स्वातंत्र्योदयः; 'belonging to the d.' उषस्य, प्रभातीय, (*s.*) in comp. —*v. i.* आविर्भू 1 P, उद्भिद् pass., उद्गम् 1 P, प्रभा 2 P; 'before the day d. ed' अप्रभातायां शर्वर्यां; 'the day d. ed' प्रभाता रजनी.

Day, *s.* दिनं, दिवसः, वासरः, अहन् *n.*, वारः 'a lunar d.' तिथि *m. f.*, 'd. by d.' दिने दिने, अनुदिवसं, प्रत्यहं; 'by d.' दिवा; 'the next d.' परेद्युः, 'the d. before' पूर्वेद्युः; 'another d.' अन्येद्युः; 'the other d.' अचिरं; 'd. and night' अहर्निशं, अहोरात्रः; दिवारात्रं, नक्तंदिवं; 'all d. long' अहर्निशं, रात्रिंदिवं, दिवा-निशं-रात्रं; 'till this d.' अद्य यावत्; 'the d. after to-morrow' परश्वः; 'he gained the d.' तस्मिन् दिने स विजयी बभूव; 'd. break' *See* **Dawn;** 'd. labour' भृतं, दैनिकं कर्म; 'd. labourer' भृतीनः; 'd. light' सूर्यप्रकाशः, दिनज्योतिस् *n.*; 'd. star' प्रभातनक्षत्रं; 'd. time' दिनकालः, दिनसमयः; 'being in the d.' दिवातन (नी *f.*); 'during d.' दिवा. **–Daily,** *a.* दैनिक-प्रात्यहिक- आह्निक (की *f.*), दैनंदिन (नी *f.*) 'd. business' आह्निकं, नित्यकर्मन् *n.* —*adv.* प्रति in comp. with 'day'; प्रत्यहं, प्रतिदिनं; दिने दिने, अहरहः. &c.

Daze, *v. t. See* **Stun.**

Dazzle, ~~*v. t.*~~ (the eye) चक्षुषः तेजः प्रतिहन् 2 P (Ka. 43), नेत्रं प्रतिहन्. **–ing,** *a.* दुष्प्रेक्ष्य, दुःनिरीक्ष्य; 'of d. splendour' प्रभाविशेषोदयदुर्निरीक्ष्यः (R. vi. 5); नेत्रप्रतिघातिन्, (विजित्य नेत्रप्रतिघातिनीं प्रभां K. v. 20).

Dead, *See* under **Die.**

Deaf, *s.* बधिर, ओत्रविकल, अकर्ण, एड; 'd. and dumb' एडमूकः. **–en,** *v. t.* बधिरयति (D.), कर्णौ उपहन् 2 P, बधिरीकृ 8 U; 'd. ing all directions with cries of alas' हाहाभिनादैर्दिशो बधिरयंतः. **–ly,** *adv.* बधिरवत्; अश्रुतिपूर्वं. **–ness,** *s.* बधिरता, एडता, श्रवणाक्षमता.

Deal, *s.* बाहुल्यं, प्राचुर्यं; 'a good d. of' बहु, प्रचुर, भूरि, विपुल; 'a good d. of corn' बहुधान्यं; 'a good d.' (*adv.*) अत्यंतं, बहु, भृशं, गाढं, अति or सु pr.: सुतप्त, अतिकृश, &c. **2** देवदारु *n.* —*v. t.* विभज् 1 U, परिकल्प् c., पृथक् पृथग् विन्यस् 4 U. **2** विकृ 6 U, न्यस् 4 P; 'd. blows' मुष्टिना प्रह् 1 P, आघातं-प्रहारं-कृ 8 U. —*v. i.* (in) पण् 1 A, व्यापृ 6 A; क्रयविक्रयं कृ, व्यवहृ 1 P; 'he does not d. in missiles' नास्य व्यवहारोऽस्त्रेषु (U. 5). **–with,** आचर् 1 P, वृत् 1 A, व्यवहृ. **2** प्रतिकृ 8 U; निरुध् 7 U; स्पर्ध् 1 A; *See* **Contend. 3** विधा 3 U, वशीकृ, विनी 1 P; 'easy to d.' विधेयः, वश्यः. **–er,** *s.* वणिज् *m.*, आपणिकः, विपणिन् *m.*, क्रयविक्रयिन् *m.* **2** व्यवहारिन्-व्यापारिन्-व्यवसायिन् *m.*; 'd. in wood' काष्ठव्यवहारकः. **–ing,** *s.* वाणिज्यं, निगमः, विपणः, क्रयविक्रयः. **2** व्यवहारः, व्यवसायः, आचरणं, व्यापारः, चेष्टितं, क्रिया, कर्मन् *n.*, वृत्ति *f.*, वर्तनं. **3** सव्यवहारः, संसर्गः, संगमः.

Dear, *a.* बहुमूल्य, महार्घ-र्ह, महामूल्य. **2** प्रिय, दयित, वल्लभ, अभिमत, इष्ट, कांत, अभीप्सित; 'd. friend' हृदयंगमः सखा; 'as d. as one's life' प्राणप्रियसम. **3** (As a term of endearment) दयित, कांत, तात, वत्स, प्रिय; 'd. Jânaki' प्रिये जानकि; वत्स राम, &c. —*adv.*, **–ly,** बहुमूल्येन, महार्घेण. **2** अत्यंतं; सुप्रियं, सुप्रीत्या, अति-सु-pr. **3** अहो, बत, हा, हंत, अहह. **–ness,** *s.* प्रियता, अभीष्टता, प्रीति *f.* **2** बहुमूल्यं, महार्घता, महार्घः.

Dearth, *s.* दुर्भिक्षं, दुष्कालः; 'd. felt' भीमाकः, प्रयामः. **2** अभावः, अप्राप्ति *f.*, विरहः, दुर्लभता.

Death, *See* under **Die.**

Debar, *v. t.* नि-प्रति-षिध् 1 P, निवारि 10, निरुध् 7 U. **2** निराकृ 8 U, निरस् 4 U.

Debark, *v. i.* उत्तॄ 1 P, नौकाया अवतॄ. —*v. t.* अवतॄ c.

Debase, *v. t.* Ex. by कृ 8 U, with **Base,** q. v.; अपकृष् 1 P, स्वपदात् पत् c. or भ्रंश् c. or च्यु c.; लघूकृ, अवज्ञा 9 P. **–ment,** *s.* अपकर्षः, अभिभवः, पदच्यावनं, लघूकरणं, अवमानना, अवज्ञा. **2** अप-नि-कृष्टता, अधोगति *f.*, नीचस्थिति *f.*

Debate, *s.* वि-,वादः, वादप्रतिवादः. वाग्युद्धं, विचारः, वितर्कः, हेतुवादः. —*v. t.* विचर् c.

वितर्क् 10; *See* **Argue.** —*v. i.* विवद् 1 A, विप्रलप् 1 P, वाक्कलहं-वादयुद्धं-कृ 8 U. **—er,** *s.* वादिन् *m.*, वितर्किन्-विवादकृत्-हेतुवादिन् *m.* **—ful,** *a.* वादप्रिय,विवादशील, वादार्थिन्.

Debauch, *v. t.* दुष् c. (दूषयति), नश् c., सत्पथात् च्यु c. or भ्रंश् c.; 'd. a girl.' (कन्यां) दुष् c., धृष् c., सतीत्वाद् भ्रंश् c., क्षतयोनिं कृ. **—**s. कामावेशः; विषयोपभोगः, विषयनिरति *f.* **—er,** *s.* विषयिन् *m.*, विषयासक्तः, कामासक्तः. विषयोपभोगरतः. 2 दुराचारः, दुश्चरितः, खंडितवृत्तः. **—er,** *s.* दूषकः, नाशकः. **—ery,** *s.* विषयासक्ति *f.*, कामासक्तता,विषयोपभोगः, व्यसनं, विषयित्वं.

Debenture, *s.* प्रतिज्ञापत्रं, नियमलेखः.

Debilitate, *v. t.* तेजो हृ 1 P or नश् c.; क्षै c. (क्षपयति), दुर्बलीकृ 8 U, क्षीणीकृ. **—ed,** *a.* दुर्बल, क्षीण, कृश, अशक्त, क्षाम. **—Debility,** *s.* दौर्बल्यं,शक्तिहीनता, क्षामता, कार्श्यं, तेजोहानि *f.*, शक्तिक्षयः, शक्तिपातः, अशक्तता.

Debit, *v. t.* देयधनभागे लिख् 6 P.

Debonair, *a.* सभ्य, शिष्ट, सुशील, सुविनीत, आर्य. **—ly,** *adv.* सभ्यवत्, सुविनीतं.

Debt, *s.* ऋणं; 'pay off or discharge a d.' ऋणं दा 3 U or शुध् c., अनृणतां-आनृण्यं गम् 1 P: 'he paid off the d. of his master by his life' स्वाम्युभिर्भर्तुरानृण्यं गतः (M. 5); 'discharge of d.' ऋणशोधनं-निस्तारः, ऋणमोक्षः; 'involved in d.' ऋणग्रस्त, ऋणिन्; 'run into or incur d.' ऋणं कृ, ऋणं ग्रह् 9 P; 'free from d.' अनृण. **—or,** *s.* ऋणिन् *m.*, अधमर्णः.

Decade, *s.* दशकं; 'd. of year' दशवर्षं.

Decadence, } **Decadency,** } *s.* क्षयः, अपपातः, अवसादः.

Decagon, *s.* दशास्रं, दशभुजः.

Decamp, *v. i.* कटकं-शिबिरं-त्यज् 1P, कटकनिवेशाद् अपसृ 1 P or अपक्रम् 1 U, 4 P, सहसा पलाय् 1 A or अपक्रम्. **—ment,** *s.* कटकत्यागः, अपसरणं, पलायनं; अपक्रमणं.

Decant, *v. t.* कान्यपात्रे स्रु c. or निक्षिप् 6 P, **—er,** काचपात्रं, कूपी.

Decapitate, *See* **Behead.**

Decay, *v. i.* क्षि pass., क्षयं-लयं-या-इ 2 P, जॄ 4 P, शॄ pass., ह्रस् 1 P, अवसद् 1 P; म्लै 1 P, नश् 4 P, म्ली 4 A, क्षै-म्लै-ग्लै 1 P, ध्वंस् 1 A; 'with d.-ed leaves' प्रपर्ण-शीर्णपर्ण:- (वृक्षः). **—***v. t.* Causal of roots above. **—***s.* क्षयः, अवसादः, जीर्णता, ह्रासः, प्रलयः; नाशः, अपचयः; क्षामता, ग्लानि *f.* **—ing,** *a.* क्षयिन्, क्षीयमाण, विशीर्यमाण.

Decease, *v. i.* मृ 6 A, उपरम् 1 P; *See* **Die.** **—***s.* मरणं, मृत्युः, निधनं, तनुत्यागः, उपरमः, संस्थानं. **—ed,** *a.* **Dead,** q. v.

Deceive, *v. t.* वंच् 10, प्रलुभ् c., मुह् c., भ्रम् c. (भ्रमयति), मुह् c.; *See* **Cheat**; 'you are much d. ed (in thinking so)' महाभ्रमोयं तव. **—er,** *s.* वंचकः, प्रतारकः, कितवः, मायिन् *m.*, धूर्तः, शठः. **—Deceit, —Deception,** *s.* प्रतारणा, कपटं, छद्मन् *n.*, छलं, वंचनं-ना, कैतवं, माया, विप्रलंभः, कूटं, अतिसंधानं, उपधिः. 2 मोहः, भ्रमः. **—ful, —Deceptive,** *a.* कपटपर, वंचक, धूर्त, वंचनशील, कपटिन्, मायिन्, छाद्मिक, शठ, कितव. 2 भ्रमकारिन्, मोहिन्, भ्रांतिजनक, मोहोत्पादक. **—fully,** *adv.* सव्याजं, छद्मना, मायया, सकपटं, छलेन.

December, *s.* सहस्यः, मार्गशीर्षपौषौ.

Decennial, *a.* दशवार्षिक (की *f.*), दशवर्षीय-ण, दशवर्षस्थायिन्.

Decent, *a.* विनीत, सविनय, समर्याद, शिष्ट, सभ्य. 2 युक्त, उचित, योग्य, उपपन्न, शिष्टाचारानुरूप, साधुसंमत. **—ly,** *adv.* सविनयं, सभ्यतया; युक्तं, यथातथं, यथोचितं. **—Decence,-cy,** *s.* विनयः, सभ्यता, मर्यादा, लज्जा, शालीनता. 2 औचित्यं, युक्तता, उपपत्ति *f.*, यथार्थता.

Decharm, *v. t.* मंत्रं प्रतिकृ 8 U.

Decide, *v.* निर्णी 1 P, व्यवसो 4 P, विनिश्चि 5 U, परिच्छिद् 7 P, अव-सम-धृ 10; 'd. a case' कार्यं निर्णी, व्यवहारं दृश् 1 P or अवेक्ष् 1 A; 'perplexed so as not being able to d.' अपरिच्छेदाकुलं (S. 5). 2 निश्चद् c., साध् c. **—ed,** *a.* निश्चित, ध्रुव, दृढ, स्थिर; स्थिरो निश्चयः; 'd. or firm resolution'; असंदिग्ध, नियत, व्यवस्थापित. **—edly,** *adv.* असंशयं, ध्रुवं, नियतं, *See* **Certainly.** **—er,** *s.* निर्णेतृ *m.*, निश्चायकः; प्रमाणपुरुषः. **—Decision,** *s.* निर्णयः, निश्चयः, व्यवसायः, संप्रधारणं, परिच्छेदः. 2 (Final result) निर्णयः; निष्पत्ति *f.* **—Decisive,** *a.* संशयच्छिद्, निर्णायक, असंदिग्ध, निश्चयकारिन्, निश्चायक; 'said in a d. ly stern tone' परिच्छेदनिष्ठुरमाहस्म (Ka. 277). **—ly,** *adv.* सनिश्चयं, असंदिग्धं, सनिर्णयं; दृढं, स्थिरतया.

Deciduous, *a.* पातुक, पतनशील, क्षयिन्, अस्थायिन्. **—ness,** *s.* अपपातः, विध्वंसः, पतनशीलता. 2 अस्थायित्वं.

Decimal, *a.* दशक, दशगुणित. **—***s.* दशांशः. **—Decimate,** *v. t.* दशमांशं ग्रह् 9 P, दशपुरुषं उद्धृ 1 P.

Decipher, *v. t.* (a letter &c.) निर्-अनुबुध् c., (गूढाक्षराणि) व्याख्या 2 P, स्पष्टीकृ 8 U, व्याकृ, विशदीकृ. **—er,** *s.* व्याख्यातृ *m.*, विवरणकृत् *m.* **—ing,** *s.* व्याख्यानं, स्पष्टीकरणं.

Deck, *v. t.* अलं-कृ 8 U, भूष् 10, मंड् 10; *See* **Adorn. 2** आच्छद् 10, आस्तॄ 9 U.–*s.* नौतलं, नौकापृष्ठं.

Declaim, *v. i.* (against) अपभाष् 1 A, निंद् 1 P, आक्षिप् 6 P; *See* **Abuse. 2** सालंकारं ब्रू 2 U, वाक्तांडवं कृ 8 U. –**er, Declamator,** *s.* वाक्पटुः, वागीशः. **2** निर्भर्त्सकः, निंदकः. –**Declamation,** *s.* सालंकारं वचनं, शब्दपांडित्यं, वाक्चातुर्यं, वाक्तांडवं.

Declare, *v. t.* वद् 1 P, कथ् 10, ख्या 2 P; आ-प्र-ख्या c. (ख्यापयति), प्र-काश् c., प्रकटीकृ 8 U, उद्-घुष् 10, नि-आ-विद् c., अभिधा 3 U. **2** उद्दीप् c., उच्चर् c., कृत् 10, स्तु 1 P, (in scriptures). –*v. i.* स्वमतं-अभिप्रायं-निविद् c. or ज्ञा c.; 'd. for ' अवलंब् 1 A, आश्रि 1 U; ' the army d. ed against its king ' स्वराजानं परित्यज्य प्रतिपक्षं समालंबत सैन्यं. –**ation,** *s.* प्रख्यापनं, प्रकाशनं, आख्यानं, ज्ञापनं, कीर्तनं, निवेदनं. **2** उक्ति *f.*, वचनं, भाषणं, प्रतिज्ञा, उपन्यासः. –**atory,** *a.* ख्यापक, ज्ञापक, निवेदक, वाचक, सूचक, अभिधायक. –**edly,** *adv.* स्पष्टं, व्यक्तं, प्रतिज्ञापूर्वकं.

Decline, *v. i.* क्षयं, ह्रासं-या-इ 2 P, or गम् 1 P, अवसद् 1 P, क्षि pass.; स्रंस् 1 A, ध्वंस् 1 A, अपचि-विशृ pass. **2** त्यज् 1 P, विचल् 1 P, निवृत् 1 A, भ्रंश् 1 A, 4 P. **3** परिणम् 1 P, आ-अव-नम्, अस्तं गम् 1 P, अस्तमवलंब् 1 A, अनेन समयेन परिणतो दिवसः (Ks. 47) ' the sun had d. ed' &c. –*v. t.* प्रत्याख्या 2 P, प्रत्याचक्ष् 2 A, प्रत्यादिश् 6 P, अपाकृ 8 U, परिहृ 10. **2** आ-अव-नम् c. (नमयति), अपकृष् 1 P, आवृज्. **3** शब्दरूपाणि आख्या or कथ् 10.–*s.* ह्रासः, क्षयः, परिणति *f.*, पातः, अवसादः, ध्वंसः. अपचयः, अस्तः; 'in the d. of life' in d.-ing years ' पश्चिमे वयसि, परिणतवयसि. **2** देहक्षयः, क्षयरोगः.–**ation,** *s.* भ्रंशः क्षयः, च्युति *f.*, &c. **2** वक्रता, अवनमनं, आवर्जनं. **3** क्रांति *f.* अपगमः.–**Declension,** *s.* विभक्तिरूपाणि, शब्दविकारः. **2** क्षयः.

Declivity, *s.* अवसर्पिणी भूमिः, उत्संगः. –**ous, Declivous,** *a.* प्रवण, अवसर्पिन्.

Decoct, *v. t.* क्वथ् 1 P, पच् 1 P. –**ion,** *s.* क्वाथः, कषायः-यं, निर्यासः.

Decollation, *s.* शीर्षच्छेदः.

Decompose, *v. t.* पृथक् कृ 8 U; व्या-कृ, वि-ली c., विद्रु c. –**ition,** *s.* पृथक्करणं, व्याकरणं, विश्लेषः, विलयः.

Decompound, *v. t.* पुनर्मिश्र् 10 **2 Decompose,** q. v.

Decorate, *v. t.* भूष् 10, प्रसाध् c., अलंकृ 8 U, मंड् 10. –**ion,** *s.* प्रसाधनं, मंडनं, भूषणं, अलंकारः, परिष्कारः, आभरणं, **2** आकल्पः, वेषः, नेपथ्यं, प्रति (परि)कर्मन् *n.* –**or,** *s.* प्रसाधकः, विभूषकः.

Decorous, *a.* विनीत, सविनय; युक्त, उचित; *See* **Decent. –Decorum,** *s.* विनयः, मर्यादा, सभ्यता, शिष्टाचारः, सुरीति *f.* सौजन्यं. **2** युक्तता, औचित्यं.

Decorticate, *v. t.* त्वचं निष्कृष् 1 P, निस्त्वचीकृ 8 U, निर्वल्कयति (D.)

Decoy, *v. t.* कपटेन आकृष् 1 P, वि-, प्रलुभ् c., प्रलुभ् c., मुह् c.; *See* **Cheat. 2** पाशे बंध् ग्रह् 9 P.

Decrease, *v. i.* परिक्षि Pass., ह्रासं गम् 1 P, or या-इ 2 P, अवसद् 1 P, ह्रस् 1 P, अल्पीभू 1 P, न्यूनीभू, अपचि pass.–*v.t.* ह्रस् c., अल्पीकृ 8 U, न्यूनीकृ, लघयति (D.), ऊन् 10, अपचि 5 U.–*s.*,–**Decrement,** *s.* ह्रासः, क्षयः, अपचयः, अवसादः, न्यूनता-त्वं, अल्पत्वं.

Decree, *v. t.* आदिश् 6 P, आज्ञा c. (ज्ञापयति), शास् 2 P. **2** दा c. (दापयति), प्रक्लृप् c., विधा 3 U, दातुं निर्णी 1 P. –*v. i.* व्यवस्थाद्वारेण निर्णी, शासनं कृ, व्यवस्थां-विधिं-कृ; विचर् c., तीर् 10. –*s.* व्यवस्था, शासनपत्रं, व्यवस्थापत्रं, विधिः, राजाज्ञा; आ-नि-देशः; आज्ञा, शासनं.

Decrepit, *a.* जराक्रांत, जरातुर, जीर्ण, जरापरिणत. –**ude,** (**d. age,**), *s.* जरा, वार्धक्यं, जीर्णावस्था, जरावस्था.

Decrescent, *a.* क्षयिन्, क्षीयमाण, क्षयिष्णु.

Decretal, *s.* विधिसंहिता.–*a* शासनपत्रनिबद्ध.

Decry, *v. t.* अप-परि-वद् 1 U, निंद् 1 P, आक्षिप् 6 P, अपलप् 1 P. –**al,** *s.* परिवादः, आक्षेपः, अपलपनं.

Decumbent, *a.* शयान, संविष्ट, निषण्ण, उपविष्ट.

Decumbence, *s.* शयनं, शय्योपवेशनं.

Decuple, *a.* दशगुण.

Dedicate, *v. t.* उत्सृज् 6 P, निक्षिप् 6 P, प्र-वि-नि-युज् 7 A, 10, **2** प्रतिष्ठा c. (-ष्ठापयति), संस्कृ 8 U, उपक्लृप् c.; (books) सम्-ऋ c. (अर्पयति) निविद् c., –**ion,** *s.* उत्सर्गः, विनियोगः, प्रतिष्ठा, संस्कारः; समर्पणं, निवेदनं.

Deduce, *v. t.* अनुमा 2 P, 3 A, ऊह् 1 A, अपवह् 1 P, निर्णी 1 P, उपलक्ष् 10.–**ible,** *a.* आनुमानिक (की *f.*), ऊहनीय. –**ment, –Deduction,** *s.* अनुमानं, अनुमिति *f.*, ऊहनं, ऊहा, अपवाहः, –**Deductive,** *a.* आनुमानिक (की *f.*). –**ly,** *adv.* अनुमानेन.

Deduct, *v. t.* वियुज् 10, अवच्छिद् 7 P, उद्धृ 1 P, व्यवकल् 10, ऊन् 10. –**ion,** *s.* वियोजनं, उद्धारः, व्यवकलनं, उद्धृतांशः.

Deed, *s.* कर्मन् *n.*, कार्यं, क्रिया, कृत्यं, चेष्टितं. **2** लेख्यप्रमाणं, लिखितं; ' sale d. ' विक्रय-

पर्वः; 'title d.' आगमः. 3 तत्त्वं, अर्थः, वस्तु n.

Deem, *v. t.* मन् 4 A, गण् 10, अवगम् 1 P, संभू c.

Deep, *a.* गभीर, गंभीर, अगाध, गहन, गाढ. 2 (of sound) मंद्र, धीर, गंभीर, मांसल, घन. 3 (of colours) घन; 'd. red' घनारुण, सुरक्त. 4 निम्न, नीच. 5 गहन, दुर्बोध, निगूढार्थ, अगम्य. 6 गभीरबुद्धि, दूरदृष्टि, विदग्ध; 'd. darkness' अंध-घोर-तमः, संतमसं; 'she is d. in love,' दूरगतमन्मथा सा (S. 3); 'd. sigh' दीर्घनिश्वासः; 'd. love' दृढबद्धं प्रेम, गाढानुरागः; 'water knee-d.' जानुदघ्नं-मात्रं-द्वयसं जलं. **-s.** **Sea,** q. v.; 'd. of night' निशीथः; घोररात्रि *f.* **-en,** *v. t.* गंभीरीकृ 8 U, घनीकृ, वृध् c. **-ly,** *adv.* गाढं, घनं, दीर्घं; अत्यंतं, अतीव, नितरां, निर्भरं, भृशं; 'sighing d.' दीर्घं निश्वस्य; 'd. sorry' शोकमग्न, अतिदुःखित; 'd. rooted' बद्धमूल. **-ness,** **-Depth,** *s.* गांभीर्यं, गाढता, घनता, अगाधता; 'd. of meaning' अर्थतोगौरवं (Mal. 1) अर्थगौरवं. 2 उदरं, गभीरस्थानं; 'the d. of lower regions' पातालोदरं. 3 वेधः, वेधनं. 4 मध्यं.

Deer, *s.* मृगः, हरिणः, कुरंगः, कुरंगमः, वातायुः, अजिनयोनिः; पृषत् *m.*, कृष्णसारः, रुरुः, शंबरः, रौहिषः, वातप्रमीः (varieties of d.)

Deface, *v. t.* विनश् c., उच्छिद् 7 P, विलुप् 6 P, or c., व्या-अप-मृज् 2 P. 2 विकृ 8 U, विरूप् 10, दुष् c. (दूषयति). **-er.** *s.* दूषकः, विनाशकः **-ment.** *s.* लोपः, उच्छेदः, दूषणं नाशनं.

De facto, *adv.* वस्तुतः, परमार्थतः.

Defalcate, *v. t.* न्यूनीकृ 8 U, ह्रस् c., अवच्छिद् 7 P, ऊन् 10. **-ion,** *s.* ह्रासः, अवच्छेदः, न्यूनता, अपचयः.

Defame, *v. t.* परि-अप-वद् 1 U, अपभाष् 1 A, आक्षिप् 6 P, गुणान्-अपलप् 1 P, अभिशंस् 1 P. **-ation,** *s.* परि-अप-वादः, आक्षेपः, अपभाषणं, निंदा, अभिशंसनं. **-atory,** *a.* परिवादक, गुणापवादक, अकीर्तिकर (री *f.*), आक्षेपगर्भ. **-er,** *s.* परिवादिन् *m.*, गुणापवादकः, आक्षेपकः, निंदकः.

Default, *s.* अपराधः, दोषः; व्यतिक्रमः, अननुष्ठानं, लोपः. 2 अभावः, असंभवः, अप्राप्तिः *f.*, 'in d. of fine' अदत्ते दंडे, दंडदानाभावे. **-er,** *s.* अपराधिन् *m.*, नियम-लंघिन्-व्यतिक्रामिन् *m.*

Defeasance, *s.* लोपः, व्यतिक्रमः, नियमभंगः-लोपः.

Defeasible, *a.* लोपनीय.

Defeat, *v. t.* परा-जि 1 A, परा-परि-भू 1 U, जि 1 P, भंज् 7 P; वि-द्रु c., पराहन् 2 P, (d. completely). 2 मोघीकृ 8 U, व्याहन् 2 P, विहन्; *See* **Baffle.** **-s.** पराजयः, परिभवः, पराभवः. अभिभवः, भंगः. 2 व्याघातः, भंगः, प्रध्वंसः.

Defecate, *v. t.* मलं हृ 1 P, शुध् c., निर्मलीकृ 8 U. **-a.** निर्मल, शोधित, हृतमल. **-ion,** *s.* शोधनं, मलहरणं.

Defect, *s.* विकारः, दोषः, छिद्रं, वैकल्यं, न्यूनता; 'bodily d.' अंगविकारः, व्यंगता. 2 अभावः, विरहः. **-ive,** *a.* विकारवत्, दोषयुक्त, सदोष, विकल; अंगहीन 2 असंपूर्ण, असमग्र, अपर्याप्त, न्यून.

Defection, *s.* त्यागः, उत्सर्गः, भ्रंशः, च्युति *f.*

Defend, *v. t.* रक्ष् 1 P, पा 2 P, त्रै 1 A, परित्रै, पा c. (पालयति) (with abl.); *See* **Protect.** 2 (In law) उत्तरं दा 3 U, पक्षं समर्थ् 10. **-ant,** *s.* प्रत्यर्थिन् *m.*, प्रतिवादिन् *m.*, अभियुक्तः. **-er,** *s.* रक्षकः, गोप्तृ *m.*, त्रातृ-रक्षितृ *m.*, पालकः, पः in comp. **-Defensive,** *a.* रक्षक, पालक, निवारक, आत्मरक्षक. **-s.** आत्मरक्षा, स्वपरित्राणं, शत्रुनिवारणं. **-Defence,** *s.* रक्षा, गुप्ति *f.*, रक्षणं, त्राणं, पालनं. 2 उत्तरं, प्रत्युत्तरं; व्यपदेशः. **-less,** *a.* अशरण, अरक्षित, अनाश्रय, अनाथ. 2 निरायुध, शस्त्रहीन.

Defer, *v. t.* विलंब् c., व्याक्षिप् 6 P. 2 (अन्यस्मिन्) निक्षिप् 6 P, न्यस् 4 P, सम्-ऋ c. (अर्पयति). **-v. i.** विलंब् 1 A, कालं क्षिप् or हृ 1 P, चिर(रा)यति (D.). 2 (to) अनुवृत् 1 A, अनुपा c. (पालयति), आदृ 6 A, सादरं आश्रि 1 U, अनुरुध् 4 A. **-ence,** *s.* अनुरोधः, अनुवर्तनं, बहुमानः, आदरः, प्रश्रयः. 2 नम्रता, विनयः, वशता. **-ring,** *s.* कालयापनं, कालहरणं, विलंबः, व्यापेक्षः.

Deficient, *a.* न्यून, ऊन, असंपूर्ण, विकल; often ex. by अल्प-हीन-रहित in comp.; 'd. in water' अल्पजल; 'd. in intellect' अल्पधी, बुद्धिहीन; 'd. in any organ' हीनांग, विकलेंद्रिय, विकलांग, अपोगंड, पो(पौ)गंड. **-Deficience, -cy,** *s.* न्यूनता, हीनता, अल्पता, अभावः, विरहः वैकल्यं, अपूर्णता. 2 दोषः, छिद्रं.

Defile, *v. t.* दुष् c. (दूषयति), मलिनीकृ 8 U, मलिनयति-कलुषयति-आविलयति (D.); 'd. a virgin' कुमारीं दुष् c., आधृष् c.; 'a d.ed virgin' क्षतयोनिः. **-v. i.** दंडव्यूहेन या 2 P or अपसृ 1 P. **-s** संबाधपथः, संकटमार्गः, दुर्मार्गः, संचारः. **-er** *s.* दूषकः. **-ment,** *s.* दूषणं. 2 मालिन्यं, कलंकः.

Define, *v. t.* लक्षणं व्याख्या 2 P; उप लक्ष् 10, परिच्छिद् 7 P, निरूप् 10, निर्वच् 2 P. 2 निर्दिश् 6 P, निर्णी 1 P, निश्चि 5 U. निर्धृ 10. 3 चिन्ह् 10, परिमा 3 A. **-er,** *s.* लक्षणव्याख्यातृ *m.*, निर्वक्तृ *m.* **-ite,** *a.*

नियत, निर्णीत, निश्चित, निर्दिष्ट; 'without any d. subject' अनिर्दिष्टकारणं. 2 परिमित, समर्याद, सावधिक. **-itely**, *adv.* निश्चितं, व्यक्तं, सनिर्णयं, सपरिच्छेदं. **-tion**, *s.* व्याख्या, परिच्छेदः, लक्षणं, विवेचनं, निर्देशः; 'my anguish transcends d.' मम विकारः परिच्छेदातीतः (Mal. 1). **-itive**, *a.* नियत, निर्णायक, स्थिर; अवश्यक.

Deflagration, *s.* दाहः, दाहनं, ज्वलनं.

Deflect, *v. i.* भ्रंश् 1 A, 4 P, च्यु 1 A. विचल् 1 P, अप-व्या-वृत् 1 A. **-v. t.** व्यावृत् c. **-ion**, *s.* भ्रंशः, च्युति *f.*, विचलनं, विमार्गगमनं. 2 उत्क्रमः, भ्रेषः.

Deflour, Deflower, *v. t.* चारित्र्यं नश् c. or हृ 1 P, दूष् c., क्षतयोनिं कृ 8 U, दुष् c. (दूषयति); 'a virgin d.-ed' क्षता, क्षतयोनिः 2 शोभां हृ or नश् c. **-er**, *s.* कुमारीदूषकः, सतीत्वनाशकः.

Defluxion, *s.* निस्यंदः, क्षरणं, स्रवणं.

Defoliation, *s.* पत्रापगमः, पर्णमोक्षः. 2 पत्रच्युतिसमयः

Deform, *v. t.* विरूप् 10, विकृ 8 U, व्यंगीकृ, विरूपीकृ. **-ed**, *a.* विरूप, विकृत, पोगंड, कु-अप-रूप, विकृतांग-व्यंग (गी *f.*); 'd. features' विकृताकारः. **-ity**, *s.* वैरूप्यं, विरूपता, कुरूपता, व्यंगता, विकृति *f.*

Defraud, *v. t.* वंच् 10, प्रतॄ c.; *See* **Cheat.** 2 छलेन-कपटेन-अपहृ 1 P. **-ation**, *s.* कपटापहरणं. **-er**, *s.* वंचकः, प्रतारकः.

Defray, *v. t.* (Expenses) दा 3 U, अपाकृ 8 U, शुध् c.; धनव्ययं-व्ययशोधनं-स्वीकृ 8 U; 'to be d.-ed' शुध् 4 P; एकस्य मूल्येन व्ययः शुध्यति, सत्रा व्ययशुद्धिः संपद्यते (P. v. 8). **-er**, *s.* व्ययशोधकः. **-ing, -ment**, *s.* व्ययशोधनं-शुद्धि *f.*

Deft, *a*, विनीत, दक्ष, चतुर, विदग्ध.

Defunct, *a.* मृत, विपन्न; *See* **Dead.** 2 (fig.) त्यक्तव्यापार, निश्चेष्ट. **-ion**, *s.* मरणं, मृत्युः, देहत्यागः.

Defy, *v. t.* तृणीकृ 8 U, अवज्ञा 9 U, अवमन् 4 A, अवगुह् 6 P, लघूकृ, तृणाय मन्-परिभू 1 P, अवगण् 10; 'I d. a king' राजेति कियती-का मम मात्रा; 'I d. you to find a mistake in my writing' मम लेखे स्खलितं कथं त्वं दर्शयसीति पश्ये तावत्; 'a disease which d.-ed medical skill' वैद्ययत्नपरिभाविनं गदं (R. xix. 53). 2 युद्धार्थं आह्वे 1 A, अभियुज् 7 A, वृ 5 P. **-ance**, *s.* समाह्वानं, युद्धाह्वानं, योधसंरावः. 2 अवज्ञा, अवमानना; 'in d. of' अवमत्य, तृणीकृत्य, अनादृत्य; ex. by gen. or loc. abs. **-ant**, *a.* उद्धत, सदर्प, सावज्ञ; अवमानिन्; 'in a d. tone' उद्धतं, सदर्पं, सावज्ञं. **-er**, *s.* समाह्वातृ *m.*, अभियोक्तृ *m.*

Degenerate, *v. i.* (कुलाचारात्) च्यु 1 A, भ्रंश् 1 A, 4 P, दुष् 4 P. **-a.** क्षीणपुण्य, -महत्त्व, परिभ्रष्ट, अपकृष्ट, कुलाचारभ्रष्ट. **-ness, -Degeneracy**, *s.* क्षीणपुण्यत्वं, कुलाचारभ्रंशः, कुलमर्यादातिक्रमः. 2 अपकर्षः, नीचावस्था, अपकृष्टदशा.

Deglutition, *s.* निगरण, ग्रसनं.

Degrade, *v. t.* (पदात् or अधिकारात्) अपकृष् 1 P, भ्रंश् c., च्यु c., अवरुह् c. (रोपयति), नीचपदं प्राप् c. 2 अवमन् c., लघूकृ 8 U, मूल्यं लघयति (D.) or ह्रस् c., 'd.-ed from office' अधिकारभ्रष्ट, पदभ्रष्ट, भ्रष्टाधिकार, पदावरोपित. **-ation**, *s.* पद-अधिकारभ्रंशः, अपकर्षः, पदच्युति *f.*, पदलोपः. 2 अवमानना, लघूकरणं, मानभंगः. 3 अपकृष्टता, अधोगति *f.*, नीचावस्था, अपकृष्टस्थिति *f.* **-ing**, *a.* लाघवकारिन्, अयशस्कर (री *f.*).

Degree, *s.* पदं, स्थानं, पदवि-वी *f.*, आस्पदं. 2 दशा, स्थिति *f.*, अवस्था. 3 उपाधिः, उपपदं. 4 कुलं, वंशः, अन्वयः. 5 प्रमाणं, परिमाणं. 6 गणः, वर्गः. 7 भागः, अंशः. 8 कोटि *f.*, काष्ठा; 'the highest d.' पराकोटिः-काष्ठा, अतिभूमिः. 9 क्रमः, अनुक्रमः, आवृत् *f.*, परिपाटि-टी *f.*, आनुपूर्व्य-र्वी, पर्यायः, तारतम्यभावः; 'in the highest d.' निरतिशयं, एकांततः; 'in some d.' किंचित्, कियताप्यंशेन, ईषत्; 'not in any d.' न केनाप्यंशेन; 'by d.s' क्रमेण, क्रमशः, शनैः-शनैः, प्रतिपदं.

Deify, *v. t.* देवत्वमारुह् c. (आरोपयति), देवं कृ 8 U. 'to be deified' देवीभू 1 P, देवत्वं इ 2 P, देवत्वमापद् 4 A. **-Deiform**, *a.* देवाकार, देवरूप. **-Deification**, *s.* ईश्वरसायुज्यं, ब्रह्मणि लयः, देवत्वप्राप्ति *f.* 2 देवत्वं, देवकरणं.

Deign, *v.* अर्ह् 1 P, प्रसद् 1 P, with inf., 'd. to look at me' मयि दृष्टिप्रसादं कुरु; *See* **Please.** 2 प्रसादपूर्वं दा 3 U, अनुग्रह् 9 P. 3 अनुज्ञा 9 U, अनुमन् 4 A.

Deism, *s.* ईश्वरवादः, आस्तिक्यं. **-Deist**, *s.* आस्तिकः, ईश्वरवादिन् *m.*

Deity, *s.* देवता, दैवतं, देवः; *See* **God.**

Deject, *v. t.* विषद् c., निर्विद् c, विषादं उत्पद् c., म्लानीकृ, धैर्यं त्यज् c. **-ed**, *a.* विषण्ण, निर्विण्ण, विषादापन्न, अवसन्न, दीन, म्लान, खिन्न; 'd. in mind' दीनमनस्, दुर्मनायमान, उद्विग्न, विमनस्, धैर्यच्युत; 'to be b. d.' विषद् 1 P, विषादं गम् 1 P, दुर्मनायते (D.), धैर्यं त्यज् 1 P. **-edly**, *adv.* सविषादं, सोद्वेगं, विषण्णं. **-edness, -ion**, *s.* विषादः, वैमनस्यं, निर्वेदः, अवसादः, उद्वेगः, विषण्णता, दीनता, म्लानि *f.*, ग्लानि *f.*, खेदः, दौर्मनस्यं.

Dejecture, *s.* अवस्करः, पुरीषं.

Delate, *v. t.* वह् 1 P, आनी 1 P. **2 Accuse,** q. v.

Delay, *v. t.* विलंब् c., व्याक्षिप् 6 P, अतिपत् c. **2** निरुध् 7 U, धृ 1 P, विष्टंभ् 9 P. **–v. i.** विलंब् 1 A, चिर(रा)यति (D.), कालं या c. (यापयति) or क्षिप् 6 P or हृ 1 P; ' why d. then ' ततः किं विलंब्यते (U. 1). **2** विकल्प् c., विचर् c. **–s.** विलंब:, व्याक्षेप:, कालातिपात:, कालयापनं, कालहरणं, कालक्षेप:. **2** आघात:, अंतराय:, विलंबं, हेतु:. **3** दीर्घसूत्रता; ' without d. ' अविलंबितं, अविलंबं, अविलंबेन, अचिरं-रात्-रेण; ' d. is dangerous ' दीर्घसूत्री विनश्यति. **–er,** *s.* कालक्षेपक:.

Delectable, *a.* रम्य, कमनीय, मनोज्ञ, आह्लादक, मनोरम-हर, रुचिर. **–Delectation,** *s.* आनंद:, आह्लाद:, प्रमोद:, हर्ष:.

Delegate, *v. t.* नियुज् 7 A, 10, व्यादिश् 6 P; प्रेष् c., (with acc. of person); न्यस् 4 P, निक्षिप् 6 P, ऋ c. (अर्पयति), प्रतिपद् c. **–s.** प्रतिनिधि:, नियोगिन् *m.*, विनियोज्य:, प्रतिपुरुष:, अधिकृत: पुरुष:. **–ion,** *s.* नियोजनं, प्रेरणं, निक्षेप:, &c.

Delete, *v. t.* अप-व्या-मृज् 2 P, विलुप् c., विनश् c., उच्छिद् 7 P. **–ion,** *s.* व्यामर्श:, लोप:, उच्छेद:. **–Deleterious,** *a* विनाशक, घातिन्, हिंस्र, घातुक.

Delf, *s.* मृद्भांडं, मृण्मयद्रव्यं, कौलालकं.

Deliberate, *v. i.* विचर् c., चिंत् 10, विमृश् 6 P, संमंत्र् 10 A, विकल्प् c.; *See* **Consider.** **–a.** कामत:-विचारपूर्वकं-कृत, विमृश्यकृत. **2** विमृश्यकारिन्, स्वहित, असाहसिक, अप्रमत्त. **–ion,** *s.* विचार:-रणं-रणा, चिंता, मंत्रणं-णा, विमर्श:, समीक्षा, वितर्क:, विवेचनं, चर्चा. **–ive,** *a.* विचारशील, विचारिन्, विमर्शिन्. **–ly,** *adv.* जानत् with अपि or एव, बुद्धिपुर:सर, कामत:, विचारपूर्वकं. **2** विमृश्य, समीक्ष्य, अवधानेन, असहसा, अप्रमत्तं. **–ness,** *s.* समीक्ष्य-विमृश्य-कारित्वं, अप्रमाद:, सावधानता, अवेक्षा.

Delicate, *a.* मधुर, स्वादु, मिष्ट. **2** ललित, चारु, शोभन. **3** (Soft) मृदु, कोमल, सुकुमार, तनु, श्लक्ष्ण, लघु, प्रतनु, विरल, परि,-पेलव; ' d. of person ' कोमलांग (गी *f.*). मृदुशरीर; ' a d. woman ' तन्वी, तन्वंगी, पेलवांगी. **4** विशिष्ट, उत्कृष्ट, उत्तम. **5** सभ्य, विनीत, शिष्ट, ' of a d. constitution ' प्रकृतिकोमल, जन्मरोगिन. **–ly,** *adv.* ललितं, सुकुमारं; मृदुतया. **–Delicacy,** *s.* माधुर्यं, स्वादुता, सौरस्यं. **2** लालित्यं, लावण्यं. **3** सौकुमार्य, मार्दवं, पेलवता, तनुता. **4** आदर:, विनय:, शिष्टाचार:, सुशीलता, सौजन्यं. **5** प्रकृतिदुर्बलता. **6** स्वाद्वन्नं, भोजनविशेष:, विशिष्टान्नं

Delicious, *a.* स्वादु, मिष्ट, रुचिकर (री *f.*), मधुर, सुरस, आस्वादवत्. **2** (of beauty &c.) मनोरम-हर, मधुर, कमनीय, रमणीय, हारिन्, चित्ताकर्षिन्. **–ly,** *adv.* स्वादु, मधुरं, मनोरमं. **–ness,** *s.* स्वादुता, माधुर्यं, रम्यता, &c.

Delight, *s.* आह्लाद:, आ-प्र-मोद:, सुखं, हर्ष:, प्रीति *f.*, प्र-सं-मद:, उल्लास:, शर्मन्, आनंद:, संतोष:, तुष्टि *f.*, मुद्-दा *f.*; 'takes no d. in sports ' नाभिनंदति केलिकला: (Mal. 3); ' thrill of d. ' पुलक:, रोमांच:; ' thrilling with d. ' आनंदपुलकिततनु:. **2** आनंदनं, आनंदद:, हर्षकर:, आनंदहेतु:. **–v. i.** ' to be d.ed ' मुद् 1 A, हृष् 4 P, आनंद् 1 P, ह्लाद् 1 A, रम् 1 A, प्री 4 A, सं-परितुष् 4 P, उल्लस् 1 P. **–v. t.** सुखयति (D.); causal of roots above. **–ed,** *a.* सानंद, प्रीत, सहर्ष, मुदान्वित, हृष्ट, आह्लन्न, आनंदित, प्रमुदित, सोल्लास, आह्लादित, उल्लसित, साह्लाद. **–ful,** *a.* प्रमोदिन्, प्रामोदिक (की *f.*), आनंदप्रद, हर्षजनन (नी *f.*), आह्लादक, आनंदक, सुखद; रुचिर, कांत, रम्य, रमणीय, मनोहर-रम. **–fully,** *adv.* सानंदं, सहर्षं, साह्लादं; रम्यं, कांतं.

Delimit, *v. t.* मर्यादीं कृ 8 U.

Delineate, *v. t.* वर्ण् 10; *See* **Describe. 2** आलिख् 6 P, चित्र् 10, चित्रे निविश् c. **–ed,** *a.* चित्रलिखित, चित्रगत, आलिखित, वर्णित. **–ion,** *s.* आलेखनं, वर्णनं. **2** आलेख्यं, चित्रं, चित्रारंभ:.

Delinquency, *s.* दोष:-अपराध:, पापं, दुष्कर्मन् *n.*, पापचरितं, अपक्रिया, दुष्कृति *f.* **–Delinquent,** *s.* पापिन्-पापकृत्-अपराधिन् *m.*, सदोष:, कृतापराध:.

Deliquesce, *v. i.* द्रवीभू 1 P, विली 9 P.

Deliquium, *s.* विलयनं, द्रव:.

Delirium, *s.* चित्तभ्रम:, चैतन्यनाश:, ज्ञानभ्रांति *f.* **–Delirious,** *a.* भ्रांतचित्त, नष्टचेतन, चैतन्यरहित.

Deliver, *v. t.* मुच् c., वि-प्र-मोक्ष् 10, उद्-हृ-धृ 1 P, निस्तॄ c., रक्ष् 1 P, परित्रै 1 A. **2** समऋ c (अर्पयति), न्यस् 4P, प्रतिपद् c., प्र-दा 3 U, 1 P, संक्रम् c., आरुह् c. (रोपयति), हस्ते निक्षिप् 6 P, हस्तं प्राप् c., हस्तगत-गामिन् *a.* कृ 8 U. (तस्य वसुधामपि हस्तगामिनीमकरोत् R. v. 1); ' shall d. it into his hand (to ... ' इमं अस्य हस्तं प्रापयिष्यामि (S. ... d. ... charge of office ' स्वाधिकारं अन्यहस्ते न्यक्षिपत्. **3** उद्-ईर् c., उच्चर् c., उदाहृ 1 P, व्याहृ, वद् 1 P. **4** (Of a message) निविद् c., कथ् 10, आख्या 2 P, आचक्ष् 2 A, शंस् 1 P. **5** (Give back) उत्सृज् 6 P, प्रतिदा, निर्यत् c., (हस्तन्यासं निर्यातय V. 5);

'd. a woman' प्रसवं कृ c., सू c.; 'to be d.ed of' प्रसू 2 A, जन् c. (जनयति), उत्पद् c.; 'was d.ed of a son' सा पुत्रं प्रासूत. **-ance**, *s.* मोचनं, मोक्षः, मुक्ति *f.*, उद्धारः, परित्राणं, रक्षणं, निस्तारणं, मोक्षणं, विमुक्तिः-मोचन. **-er**, *s.* मोचकः, रक्षकः, त्रातृ *m.*, मुक्तिदातृ *m.*, तारकः, उद्धर्तृ *m.* 2 निवेदकः,आख्यायकः. **-y**, *s.* मुक्ति *f.*; *See* **Deliverance**, above. 2 अर्पणं, निक्षेपणं, प्रतिपादनं, संक्रामणं, न्यसनं, प्रदानं. 3 उच्चारणं, उदीरणं, व्याहारः-हरणं; 'a fluent d.' अस्खलितभाषणं, अप्रतिहतभाषणौघः-वाक्सरणिः. 4 निवेदनं, विज्ञापनं, विज्ञप्ति *f.*, कथनं. 5 उत्सर्गः, निर्यातनं, वितरणं. 6 प्रसवः, प्रसूति *f.*, गर्भमोचनं; 'd. bed' अरिष्टशय्या, 'a woman near her d.' आसन्न-प्राप्त-प्रसवा; 'place of d.' अरिष्टं, सूतिकागृहं.

Dell, *s.* दरी, गुहा, कंदरः.

Delude, *v. t.* मुह् c., वंच् 10, प्रलुभ् c., आकृष् 1 P, वि-सं-भ्रम् c. (भ्रमयति); *See* **Cheat** also. **-er**, *s.* मोहकः, वंचकः, प्रतारकः, मायिन् *m.* **-Delusion**, *s.* मोहः, भ्रमः, आभासः, माया, मतिभ्रमः, इंद्रजालं, विवर्तः; 'the world is all a d.' विश्वमिदं मायामयं, असारं, विवर्त एव. 2 वंचनं, प्रतारणा, प्रलोभनं, कपटं. **-Delusive,-Delusory**, *a.* मायामय (यी *f.*), असार, मायिन्, मोहक, ऐंद्रजालिक (की *f.*), मोहिन्, मोह-भ्रांति-जनक.

Deluge, *s.* आप्लावः, संप्लवः, जलप्रलयः, भूतसंप्लवः, तोयविप्लवः, 'universal d.' प्रलयः, महासंप्लवः, संवर्तः, क्षयः, कल्पांतः. 2 धारासंपातः, वारिपूरः, अविरलधारासारः, अतिवृष्टिः *f.* 3 उत्पातः, आकस्मिकी आपद्. *-v. t.* प्लु c., आ-सं°, निमस्ज् c. (मज्जयति).

Delve, *v. t.* खन् 1 P, नि-अव°; उर्वीं भिद् 7 P **-s.** खातं, विवरं, बिलं, गर्ता-र्तः. **-er**, *s.* खनकः, खनितृ *m.*

Demagogue, *s* प्राकृतजननायकः, प्रजानायकः.

Demain, Demesne, *s.* स्वाधीना भूमिः.

Demand, *v. t.* प्रच्छ् 6 P, अनुयुज् 7 A, ज्ञा deside. (जिज्ञासते); 'd. ed his name' किं तव नामेति पप्रच्छ; 'd. a boon' वरं वृ-वृ-5, 9 U. 2 **Claim**, q. v. 3 अर्ह् 1 P, oft. by pot. pass. part.; 'Oh Goddess, Godâvari the matter d. s thy care (attention)' भगवति गोदावरि तत्र त्वया सावधानया भवितव्यं (U. 3); अयमर्थोविचारमर्हति 'd. s consideration'; 'this offence d. s an atonement of serious expense' भूरिद्रव्यव्ययेनायं दोषः प्रमार्ष्टुं शक्यः, भूरिधनव्ययसाध्यप्रायश्चित्तः दोषः. **-s.** प्रश्नः, अनुयोगः, पृच्छा, जिज्ञासा. 2 अभियोगः, प्रार्थना; याचना; 'on d.' वार्तां पृष्टः

सन्. **-ant,-er**, *s.* प्रार्थयितृ *m.*, याचितृ *m.*, अभियोक्तृ *m.*, अर्थिन् *m.*

Demarkation, *s.* सीमा-मर्यादा-परिच्छेदः.

Demean (oneself), *v. i.* वृत्तिं अनुष्ठा 1 P, चेष्ट् 1 A, वृत् 1 A, व्यवहृ 1 P; *See* **Act. -our**, *s.* वृत्ति *f.*, आचरणं, आचारः, चेष्टितं, व्यवहारः.

Dementate, *v. t.* उन्मद् c., संज्ञां अपहृ 1 P. **-a.** उन्मत्त, नष्टसंज्ञ, मूढचित्त.

Demerit, *s.* अगुणः, दोषः, न्यूनता.

Demi, अर्ध, सामि *ind.* in comp.

Demi-god, *s.* नरदेवः, विद्याधरः, यक्षः, गंधर्वः, उपदेवता, देवयोनिः

Demi-man, *s.* अर्धपुरुषः-नरः, किंनरः.

Demise, *s.* मृत्युः, मरणं, उपरति *f.* 2 समर्पणं, विधिवत् प्रदानं. *-v. t.* मृत्युपत्रेण प्रदा 3 U.

Demission, *s.* अवपातः, अवसादनं, अपकर्षणं.

Demobilize, *v. t.* *See* **'Disband.'**

Democracy, *s.* प्रजाप्रभुत्वं, प्रजासत्तात्मकं राज्यं, प्रजातंत्रं. **-Democrat**, *s.* प्रजातंत्रवादिन् *m.*, प्रजापक्षानुकूलः, प्रजाप्रभुत्वानुग्राहकः, प्रजापक्षावलंबिन् *m.* **-tical**, *a.* सार्वलौकिक (की *f.*), प्रजातंत्रीय.

Demolish, *v. t.* विनश् c., उच्छिद् 7 P, अवसद् c., ध्वंस् c., प्र-वि°; उन्मूल् 10, उत्पट् 10. **-er**, *s.* विनाशकः, उच्छेदकः. **-Demolition**, *s.* विनाशः, उच्छेदः, प्र-विध्वंसः, उन्मूलनं, उत्पाटनं, अवसादनं.

Demon, *s.* दानवः, असुरः, रक्षस् *n.*, राक्षसः, दैत्यः, दनुजः, दैतेयः, सुरद्विट्; भूतः, पिशाचः, रात्रि(त्रिं)चरः, निशाचरः, यातुधानः. **-iac**, *s.* भूताविष्टः, वेतालोपहतः. *-a.*, **-iacal**, *a.* राक्षस (सी *f.*), पैशाच (ची *f.*), आसुर (री *f.*), (*s.*) in comp. **-ology**, *s.* भूतपिशाच-विद्या.

Demonstrate, *v. t.* साध् c., सिध् c. (साधयति), प्रदृश् c., प्रतिपद् c., उपपद् c., प्रमाणयति (D.); निर्णी 1 P, निर्दिश् 6 P. **-ion**, *s.* साधनं, सिद्धि *f.*, उपपत्ति *f.*, प्रतिपादनं. 2 निर्णयः; प्रामाण्यं, सिद्धांतः; 'ocular d.' प्रत्यक्षप्रमाणं-चाक्षुषज्ञानं-प्रमाणं. **-ive**, *a.* दर्शक, निर्देशक, निर्णायक, प्रतिपादक, सिद्धांतकरण. **-ively**, *adv.* सिद्धिपूर्वं. सप्रमाणं, सुव्यक्तं, सोपपत्तिकं. **-or**, *s.* निर्देशकः, प्रतिपादकः, प्रदर्शकः.

Demoralize, *v. t.* धर्मात्-आचारात्-भ्रंश् c. or च्यु c., आचारं दुष् c. (दूषयति), भ्रष्टीकृ 8 U, दुर्वृत्त *a.* कृ **-ation**, *s.* आचारभ्रष्टता, धर्मच्युति *f.*, धर्म-आचार-विप्लवः, अपकर्षः

Demulcent, *a.* शामक, शांतिद. 2 स्निग्ध, चिक्कण.

Demur, *v. i.* शंक् 1 A, वि-आ°; विचर् c., विकृप् c., विलंब् 1 A, मनसा दोलायते (D.); सवितर्कं व्याक्षिप् c. **-s.** आशंका-

संदेहः, वितर्कः, विचारणं, विकल्पः; 'without d.' अविचारितं, अविलंबं.

Demure, *a.* विनीत, अतिनम्र, गंभीर, धीर, शांत, सलज्ज, सव्रीड, अचपल; 'with d. looks' सव्रीडवदन. **-ly,** *adv.* सलज्जं, सव्रीडं, धीरं, सविनयं. **-ness,** *s.* विनयः, नम्रता, गांभीर्यं, त्रपा, लज्जा, व्रीडा, ह्रीः.

Den, *s.* बिलं, विवरं, गुहा, गह्वरं, कंदरः, कुहरं.

Dengue, *s.* संधिज्वरसंनिपात,

Denizen, *s.* नि-वासिन् *m.*, ओकस् in comp.; 'd. of heaven' दिवौकसः, &c. **2** पौरः, नागरः, नगरजनः, स्वसंजनः.

Denominate, *v. t.* वद्-भण्-वद् आह्वे 1 P, व्यपदिश् 6 P, अभिधा 3 U, वच् 2 P, ख्या 2 P; *See* **Call** also. **-ion,** *s.* नामन् *n.*, अभिधानं, संज्ञा, आख्या. **-ive,** *a.* अभिधायिन्, आख्यायक (in grammar) नामधातुः. **-or,** *s.* नामकृत्-नामदातृ *m.* **2** हरः, हारः, छेदः; 'of the same d.' समच्छेद; 'reduced to the same d.' सवर्णित.

Denote, *v. t.* निर्दिश् 6 P, सूच् 10, उपलक्ष् 10, वच् 2 P, अभिधा 3 U, सूच् c., गम् c. (गमयति); oft. ex. by अर्थ in comp.; *See* **Mean**; 'the word क्षेत्र here d. s body' अत्र क्षेत्रशब्दः शरीरार्थे-र्थः. **-ation,** *s.* निर्देशः,सूचनं, अभिधा-धानं, उपलक्षणं-णा. **-ing, -ative,** *a.* सूचक, दर्शक, वाचक, अभिधायक, गमक.

Denouement, *s.* कार्यं, निर्वहणं, निष्ठा.

Denounce, *v. t.* (अमंगलं or अनिष्टं) प्रकाश् c. ख्या c. (ख्यापयति), आ-नि-विद् c., कथ् 10. **2** प्रकाशं तर्ज् 10 A, भर्त्स् 10A, अभिशप् 1 U, अभिशंस् 1 P, निंद् 1 P, गर्ह् 1, 10 A, आक्रुश् 1 P. **-er,** *s.* अनिष्टावेदकः. **2** अधिक्षेपकः, निंदकः. **-ment, Denunciation,** *s.* अनिष्टख्यापनं-प्रकाशनं. **2** निर्भर्त्सना-नं, आक्रोशः, अभिशंसनं, निंदा, गर्हा.

Denovean } *adv.* पुनर्, भूयः.
Denovo }

Dense, *a.* घन, निबिड, सांद्र, अविरल, निरंतर. अनंतर गाढ, बहुल. **2** सुसंहत, दृढ, पीवर. **-ity,** *s.* घनता, सांद्रता, आनंतर्यं; पीवरता.

Dent, *s.* प्रहार-आघात-चिह्नं.

Dental, *a.* दंत्य; 'a d. letter' दन्त्यं.

Dented, Dentated, *a.* दंतुर, भंगुर, अनुक्रकच.

Dentifrice, *s.* दंतशोधनं-धावनं.

Dentist, *s.* दंतवैद्यः-चिकित्सकः.

Dentition, *s.* दंतोद्भवः, दंतवृद्धि *f.*

Denude, Denudate, *v. t.* नग्नीकृ 8 U, विवस्त्रीकृ विवासयति (D.), वस्त्रं अपहृ 1 P, शून्यीकृ; निर् in comp.; 'a tree d. of leaves' निष्पत्रो or निष्पत्रीकृतो वृक्षः.

Deny, *v. t.* अपलप् 1 P, अपवद् 1 P, न स्वीकृ-अंगीकृ 8 U, निषिध् 1 P, प्रत्याख्या 2 P, नि-अप-ह्नु 2 A, प्रत्यादिश् 6 P. **-al,** *s.* अपनिह्नवः, प्रत्यादेशः, निषेधः, अस्वीकारः, प्रत्याख्यानं, अपलापः; 'self d.' आत्मसंयमः, आत्मनिग्रहः. **-er,** *s.* नि-ह्नोतृ *m.*, अपलापिन् *m.*, प्रत्यादेशकः.

Deobstruct, *v. t.* निर्विघ्नीकृ 8 U, विघ्नान् हृ or अपनी 1 P.

Deodand, *s.* देवोपहारः.

Deodorize *v. t.* दुर्गंधं हृ or अपनी 1 P.

Depaint, *See* **Paint.**

Depart, *v. i.* प्रस्था 1 A, प्रया 2 P, वि-निर्-गम् 1 P, अपक्रम् 1 U, 4 P, अपया, अप-इ 2 P, अपगम् अपसृ-सृप् 1 P, 'whose life has d. ed' वि-गत-जीवितः. **2** म-इ, देहं उत्सृज् 6 P, विपद् 4 A, मृ 6 A, संस्था 1 A; *See* **Die.** **-v. t** त्यज् 1 P, हा 3 P, उत्सृज्. **-ed,** *a.* अपगत, व्यपेत; 'not d. from the meaning' अर्थादनपेत, अर्थ्य. **2** प्रेत, मृत, दिवंगत, संस्थित, विपन्न. **-ment,** *s.* भागः, विच्छेदः, प्र-वि-भागः. **2** विषयः, प्रकरणं, अंगं. **3** अधिकारः, नियोगः, कर्मन् *n.*, व्यापारः. **4** देशः, विषयः, मंडलं. **-ure,** *s.* अपगमः, अपयानं, प्रस्थानं, प्रयाणं, अपसरणं, अपसृति *f.*, निर्गमः, अपक्रमः. **2** देहत्यागः, संस्थिति *f.*, मरणं, उपरति *f.*

Depend, *v. i.* अवलंब् 1 A, प्रलंब्. **2** अव-आलंब्, आश्रि 1 U, संश्रि; निबंधन, तंत्र, अधीन, आयत्त, वश, in comp.; 'every thing d. s on fate' सर्वं दैवाधीनं-यत्तं; मम प्राणास्त्वदाशानिबंधनाः (M. 4); oft. by अपेक्ष् 1 A, व्यपेक्ष्; *See* below. **3** अनु-उप-जीव् 1 P. **4** (rely) विश्वस् 2 P (with loc.): समर्-कृ c. (अर्पयति.); 'I d. upon you alone' त्वय्येव मे विश्वासः; 'd. upon it, I shall starve myself to death' मया प्रायोपवेशनं कृतं विद्धि (P. iv. 1); 'd. upon it' असंशयं, निश्चितं, ध्रुवं, खलु. **5** संबंध्, प्र-अनु-संबंध् pass., समनु-इ 2 P. **-ance, -ence,** *s.* अवलंबनं, आश्रयः, संश्रयः, निष्ठा, तंत्रता, निबंधनं, अधीनता; 'mutual d.' परस्परनिबंधनं, अन्योन्याश्रयः. **2** पराधीनता, परवशता, परवत्ता, पारतंत्र्यं, परायत्तत्वं. **3** विश्वासः, प्रत्ययः. **4** संबंधः, अनुबंधः, समन्वयः, संपर्कः. **-ency,** *s.* आयत्तता, अधीनता, &c. **2** अधीनः प्रदेशः, अन्यतंत्रं राज्यं. **-ant, -ent,** *a.* प्रलंब. **2** अधीन, आयत्त, आश्रित, अवलंबिन्, वश, तंत्र, निबंधन in comp. **3** (d. on another) पराश्रित, पराधीन, परतंत्र, परवश, परवत्, परवत्; 'd on a cause' निमित्तापेक्षः (Mal.

-*s*. उप-अनु-जीविन् *m*., आश्रितः, परपक्षो जनः, भृत्यः, परिवारः.

Depict, *v. t.* आलिख् 6 P, वर्ण् 10, निर्दिश् 6 P.

Depilation, *s.* लो(रो)महरणं, उल्लुंचनं. **-Depilatory,** *a.* केशनाशक, लोमहारिन्.

Depilous, *a.* अकेश, रो(लो)महीन.

Deplete, *v. t.* शून्यीकृ 8 U, रिच् c. निःशिष् c. **-ion,** *s.* अपक्षयः, निःशेषता, रिक्तता, शून्यत्वं, शून्यीकरणं.

Deplore, *v. t.* शुच् 1 P, विलप् 1 P, परिदेव् 1 A, परिदेव् 10 A. *See* **Lament. -ably,** *adv.* शोच्यप्रकारेण, शोचनीयं. **-or,** *s.* परिदेवकः, अनुशोचकः.

Deploy, *v. t.* विस्तृ 9 U (सैन्यव्यूहान्).

Deplume, *v. t.* पक्षान् उत्पट् 10 or उद्धृ 1 P, निष्पक्षीकृ 8 U. **-ation,** *s.* पक्षोत्पाटनं.

Depone, *v. i.* सशपथं वद् 1 P or कथ् 10, शपथपूर्वं उपदिश् 6 P or प्रत्यक्ष् 4 U. **-ent,** *s.* साक्षिन् *m*. 2 अकर्तरि क्रिया.

Depopulate, *v. t.* निर्जनीकृ 8 U, विजनीकृ, नरशून्य *a*. कृ; उपपीड् 10, बाध् 1 A, समुच्छिद् 7 P. **-ion,** *s.* निर्जनीकरणं 2 उपद्रवः, उच्छेदः, उपपीडनं, बाधा. **-or,** *s.* उच्छेदकः, उपपीडकः, विप्लवकारिन् *m*.

Deport, *v. t.* प्रव्रज् c., निः-प्र-वि-वस् c., देशांतरं नी c. (नयति). **-v. i.** (oneself) आचर्-व्यवहृ 1 P, वृत् A; *See* **Act. -ation,** *s.* प्र-वि-वासनं, प्रव्राजनं. **-ment,** *s.* वृत्ति *f*., आचरणं, चेष्टितं, व्यवहारः, वृत्तं.

Depose, *v. t.* (राज्यात् or अधिकारात्) अवरुह् c. (रोपयति), भ्रंश् c., पत् c., च्यु c. **-v. i.** साक्ष्यं दा 3 U, वद् 1 P, वच् 2 P, कथ् 10. **-ition,** *s.* साक्ष्यं, साक्ष्यदानं. 2 (Deposal) राज्यभ्रंशः-च्युति *f*., राज्यावरोपणं, अधिकारच्युतिः-भ्रंशः.

Deposit, *v. t.* निक्षिप् 6 P, न्यस् 4 P, निधा 3 U, आधा, अृ c. (अर्पयति), आधीकृ 8 U. **-s.** न्यासः, निक्षेपः, आधिः, उपनिधिः. 2 किट्टं, शेषः, खलं, कालुष्यं, मलः-लं **-ary,** *s.* निक्षेपग्राहकः, न्यासधारिन् *m*. 2 निधानस्थानं-गर्भ-भूमि *f*. **-or,** *s.* निक्षेपितृ *m*., न्यासकर्तृ *m*. **-ory,** *s.* आधारः, आश्रयः, निधानं, निधिः, भाजनं, आगारं, संग्रहस्थानं.

Depot, *s.* आगारं, शाला, स्थानं, आलयः, 'book d.' पुस्तकालयः, ग्रंथशाला; 'military d.' युद्धसामग्र्यागारं.

Deprave, *v. t.* दुष् c. (दूषयति) भ्रंश् c. मलिनीकृ 8 U, कलुषयति (D.). **-ed,** *a.* दुराचार, भ्रष्ट, दुष्ट, मलिनीकृत, दुरात्मन्, पापचेतस्, दुर्वृत्त, भ्रष्टशील, कलुषाचार. **-edness,-ity,** *s.* दुष्टता, भ्रष्टता, दुष्टभावता, दौरात्म्यं, दुराचारता, दौर्जन्यं, कालुष्यं, दुर्वृत्तता.

Deprecate, *v. t.* (प्रार्थनापूर्वकं) निवृ 10, व्यावृत् c., मा भूदिति याच् 1 A. 2 अनुक्रुश् 1 P. **-ion,** *s.* निवारणार्थं प्रार्थनास्तवः. **-ive,-atory,** *a.* अनिष्टनिवारक.

Depreciate, *v. t.* अर्घतः पत् c., अवमन् 4 A, लघूकृ 8 U, लघु मन्, मूल्यं न्यूनीकृ, अवक्षिप् 6 P. अपलप् 1 P, अपकृष् 1 P. **-ion,** *s.* लघूकरणं, अवमानना, अपकर्षः, अपलापः.

Depredate, *v. t.* अपहृ 1 P, लुंठ्-ट् 1 P, 10, उपद्रु 1 A, उपद्रुत्य ग्रह् 9 P. **-ion,** *s.* उपप्लवः, अपहरणं, लुंठनं, लोप्त्रग्रहणं. **-or,** *s.* विप्लवकारिन् *m*., अपहारकः.

Deprehend, *See* **Apprehend.**

Depress, *v. t.* अवनम् c. (नमयति), पत् c., अपकृष् 1 P, अवपीड् 10, निम्नीकृ 8 U, अवसद् c., भ्रंश् c., अवगाह् 1 A. 2 विषादं नी 1 P, विषद् c., विषण्णीकृ; 'd.ed behind' पश्चादवनताङ्गी (S. 3); 'd.ed in spirits' विषण्ण, म्लान, मुक्तावयव. खिन्नचित्त; *See* **Dejected -ion,** *s.* पातः, अवनमनं, अपकर्षः-र्षणं. 2 विषादः. खिन्नता, अवसादः, उद्वेगः, दौर्मनस्यं, म्लानि *f*., 'd. of spirits' सत्त्वभ्रंशः.

Deprive, *v. t.* अपनी 1 P, अपहृ 1 P, (with gen. of person); भ्रंश् c., च्यु c. (with abl.); वियुज् 7 A, 10, विनाकृ 8 U, (with instr. of the object deprived). **-ation,** *s.* हरणं, अपचयः, क्षयः, लोपः, हानि *f*., नाशः. **-ed,** *a.* हृत, अपहृत, हीन, वियुक्त, भ्रष्ट, विरहित, विनाकृत (gen. in comp.), वीत-लुप्त निर् in comp.; 'd. of wealth' निर्धन, लुप्तवित्त; 'd. of authority' भ्रष्टाधिकार, पदभ्रष्ट; 'to be d.' हा pass.; परिहा, वियुज् pass.

Depure, Depurate, *See* **Purify.**

Depute, *v. t.* नियुज् 7 A, 10, प्रेर् c., प्रेष् c., प्रहि 5 P, समादिश् 6 P (of a person); निक्षिप् 6 P, न्यस् 4 P, (of business). **-ation,** *s.* नियोजनं, प्रेरणं, प्रेषणं. 2 नियुक्ताः-समादिष्टाः (*pl.*), नियोगिगणः, नियुक्तजनाः. **-y,** *s.* प्रतिनिधिः. प्रतिहस्तः-स्तकः, नियोगिन् *m*.; नियुक्तः, प्रतिपुरुषः.

Deracinate, *See* **Eradicate.**

Derail, *v.* लोहमार्गात् निःसृ 1 P, or c.

Derange, *v. t.* विपर्यस् 4 U, विक्षिप् 6 P, क्रमं-व्यवस्थां-भंज् 7 P, or उपहन् 2 P, विक्षुभ् c., संकृ 6 P, आकुलीकृ 8 U. **-ed,** *a.* व्यस्त, अव्यवस्थित, भग्नक्रम, अव्यवस्थित, विक्षिप्त, संकीर्ण; 'd. in mind' उन्मत्त, भ्रांतचित्त. **-ment,** *s.* व्युत्क्रमः, क्रमभंगः, अव्यवस्था, व्यस्तता, अक्रमः. विप्लुतता, वैकल्यं; 'd. of mind' मतिभ्रमः चित्तविभ्रमः, मतिविपर्यासः.

Derelict, *a.* त्यक्त, उत्सृष्ट, परित्यक्त. **-ion,** *s.* त्यागः, उत्सर्गः, उपेक्षा.

Deride, *v. t.* वि-उप-अव-हस् 1 P, उपहासास्पदी कृ 8 U, अवज्ञा 9 U, भर्त्स् 10 A, गर्ह् 1, 10 A; 'to be d. ed' उपहास्यतां गम् 1 P, उपहासास्पदं भू 1 P; 'are d.ed by all' सर्वजनस्योपहास्यतामुपयांति (Ka. 108). **-er,** *s.* उपहासकः, अवक्षेपकः. **-ingly,** *adv.* अवहासेन, उपहासपूर्वं, सोपहासं. **-Derision,** *s.* उप-अव-हासः, अवमानना, धिक्कारः, अवज्ञा, गर्हणं, निर्भर्त्सनं. **-Derisive,** *a.* सोपहास, अवहासगर्भ, अवहासिन्; उपहास्य; गर्ह्य.

Derive, *v. t.* निष्कृष् 1 P, उद्-भू c., जन् c. (जनयति). उत्पद् c., **2** प्राप् 5 P, लभ् 1 A, Ge , q. v.) **3** व्युत्पद् c. निर्वच् 2 P, 10, व्युत्पत्तिं वद् 1 P. **-ed,** *a.* उत्पन्न, उद्भूत; oft. ex. by प्र-,भव-मूल-उद्भव-ज in comp., 'the race d. ed from the Sun' सूर्यप्रभवो वंशः; 'to be d. ed' उत्पद् 4 A, प्रभू 1 P, जन् 4 A, उद्-भू, निर्गम् 1 P. **-ation,** *s.* व्युत्पत्ति *f.*, निर्वचनं, शब्दोत्पत्ति *f.*, शब्दयोनि *f.* **2** प्रभवः, उद्भवः. योनि *f.*, मूलं, निर्गमः. **-ative,** *a.* व्युत्पन्न; यौगिक (की *f.*). 'd. suffixes' तद्धितप्रत्ययाः. **-s.** साधितः शब्दः, व्युत्पन्नः शब्दः.

Dermis, *s. See* **Skin.**

Derogate, *v. t.* अल्पीकृ 8 U, न्यूनीकृ, लघयति (D.): *See* **Depreciate. -ion,** *s.* लघूकरणं, अपमानः, गौरवन्यूनता अवमानना, लाघवं. **-ory,** *a.* अननुरूप; अकीर्तिकर, लाघवकारिन्, असदृश शी *f.*), अयशस्करी (री *f.*).

Dervise, *s.* संन्यासिन् *m.* (महंमदीयः).

Descant, *v. i.* सविस्तरं व्याख्या 2 P, वि-वृ 5 U, विस्तरेण वर्ण् 10. **2** गै 1 P, वर्ण् 10. **-s.** वचनं, वादः, प्रवादः, भाषितं. **2** गीतं.

Descend, *v. i.* अवतॄ-अवरुह्-अवपत् 1 P, निपत्, च्यु 1 A, भ्रंश् 1 A, 4 P. **2** आ-अभि-गम् 1 P, प्रविश् 6 P. **3** (upon) अभिद्रु 1 P, अभियात् 1 P, आक्रम् 1 U, 4 P: *See* **Attack. 4** (from) उत्पद् 4 A, प्र-उद्-भू 1 P, जन् 4A; *See* **Derive.** वंश-कुल-क्रमेण आगम् 1 P, or या 2 P, परंपरया प्राप् pass.; 'd. into details' सविस्तरं वर्ण् 10, विस्तरशः वद् 1 P, प्रपंचयति (D.) **-v. t.** Causal of roots (1) above. **-ant,** *s.* वंश्यः, वंशजः, अपत्यं, संतति *f.* प्रसूति *f*, संतानः; 'd. s.' पुत्रपौत्राः, कुलसंततिः, वंशः, अन्वयः, कुलं; 'male d.' पुत्रसंतानः. **-ed,** *a.* अवतीर्ण, अधोगत; 'lineally d.' कुलक्रमागत, वंशपरंपराप्राप्त, क्रमायात, पितृप्राप्त; 'to be d.' उत्पद्. जन्, प्रभू 1 P; gen. by derivative affixes; 'd. from Puru' पौरवः. **-ent,** *a.* अवरोहिन्, अधोगामिन्. **-Descent,** *s.* अवतरणं, अवपातः, अवरोहः-हणं, अवतारः. **2** आक्रमः, अवस्कंदः, अभिद्रवणं. **3** जन्मन् *n.*, उत्पत्ति *f.*, वंशः, उद्भवः, कुलं; 'of noble d.' कुलीन, कुलोत्पन्न, महाकुलप्रसूत, अभिजात, अभिजनवत्. **4** संतति *f.*, अन्वयः, आवलि-ली *f.*, संतानः-नं. **5** वंशक्रमागमः, अन्वयागमः. **6** अवसर्पिणी भूमिः, प्रवणस्थानं.

Descension, *s.* अवपातः, अधोगमनं, अधःपतनं.

Describe, *v. t.* वर्ण् 10, निर्दिश् 6 P, वि-वृ 5 U, कृत् 10, कथ् 10, निरूप् 10, वच्. 2 P, व्याख्या 2 P; 'her splendour can't be d. ed' तस्याः श्रीर्वचनानामविषया. **2** (Draw) लिख् 6 P. **-Description,** *s.* वर्णनं-ना, निर्देशः, व्याख्यानं, कथनं, निरूपणं, विवरणं. **-Descriptive,** *a.* निर्देशक, वाचक, अभिधायिन्, निर्देशिन्. **2** वर्णनपर.

Descry, *v. t.* दूरात् आलोक् 1 A, 10 or दृश् 1 P, or ईक्ष् 1 A, निवर्ण् 10, आलक्ष् 10. **2** ज्ञा 9 U, अवगम् 1 P; *See* **Know.**

Desecrate, *v. t.* दुष् c. (दूषयति), अपवित्रीकृ 8 U, पुण्यत्वं लुप् c., संस्कारहीन *a.* कृ. **-ion,** *s.* दूषणं, संस्कारदूषणं, अपवित्रीकरणं.

Desert, *s.* मरुः, मरुस्थलं-ली, वालुकाप्रदेशः, धन्वन् *m.* **2** गुणः, पुण्यं, योग्यता, पात्रत्वं, पुण्यापुण्यं, अर्हत्वं, **-a.** निर्जन, निर्मानुष (षी *f.*), वन्य, खिल, निर्जल, शून्य, आरण्यक. **-v. t.** त्यज् 1 P, हा 3 P, उत्-विसृज् 6 P, रह् 10, (रहयति), अपन्यस् 4 P, **-v. i.** सेनां त्यक्त्वा पलाय् 1 A. **-er,** *s.* त्यागिन् सेनात्यागिन् *m.*, परावर्तकः. रणपराङ्मुखः, पलायिन् *m.* **-ion,** *s.* त्यागः, उत्सर्गः; सेनात्यागः, निर्गमनं, अपक्रमणं. **-less,** *a.* निर्गुण, अनर्ह, अयुक्त, अपात्र.

Deserve, *v. t.* अर्ह् 1 P, अर्ह-उचित-योग्य *a.* in comp.; oft. by pot. pass. part. **-ed,** *a.* योग्य, उचित, अर्ह. **-edly,** *adv.* उचितं, योग्यं, न्यायतः. **-er, -ing,** *a.* अर्हत् गुणवत्, अर्ह, उचित, योग्य, पात्र; 'd of' ex. by pot. pass. part. 'd. of pity' अनुकंप्य, &c. **-s.** गुणः, पात्रता, योग्यता, अर्हत्वं.

Deshabille, *See* **Dishabille.**

Desiccate. *v. t.* शुष् c., आचम् 1 P, **-v. i.** शुष् 4 P, **-ion,** *s.* शोषणं, परिशोषः. **-ive,** *a.* शोषक. **-Dessicants,** *s.* व्रणशोषकाः.

Desiderate, *See* **Desire. -ive,** *a.* इच्छार्थक, सन्नंत. **-Desideratum,** *s.* अभीष्टवस्त्वभावः.

Design, *v. t.* परि-सं-कल्प् c., अनुसंधा 3 U, व्यवसो 4 P, अभि-प्र-इ 2 P, उद्दिश् 6 P; चिंत् 10, घट् c. (घटयति), मनः-मतिं कृ.

8 U. 2 प्र-विनि-युज् 7 A, 10. 3 आलिख् 6 P, सूत्रपातं कृ. **-s.** अभिप्रायः, अर्थः, आकांक्षा, उद्देशः, संकल्पः, आशयः, हेतुः, चिकीर्षितं, प्रयोजनं, कार्यं. 2 उपायः, चिंता, कल्पना, घटना, विधानं, व्यवसायः. 3 आलिखनं, सूत्रपातः, संस्कारः. **-edly,** *adv.* कामतः, यथाकामं, इच्छातः, बुद्धिपुरःसरं. **-er,** *s.* चिंतकः, परिकल्पकः. 2 आलेखकः, सूत्रपातकः. **-ing,** *a.* उपजापिन्, मायिन्, छलिन्, वंचनशील, प्रतारक, विदग्ध, कपटपटु, धूर्त. **-less,** *a.* निरर्थक, निष्प्रयोजन.

Designate, *v. t.* उप-लक्ष् 10, अप-व्यप-दिश् 6 P, निर्दिश्, सूच् 10, सूत c., अभिधा, 3 U, निर्वच् 2 P, गम् c. (गमयति). 2 नियुज् 7 A, 10, परि-सं-कृप् c. **-ing,** *s.* लक्षणं, उपलक्षणं, चिह्नं, विशेषणं, अभिधानं, संज्ञा, आख्या, नामन् *n*

Desire, *v. t.* इष् 6 P, वांछ् 1 P, कम् 10 A, स्पृह् 10 (with dat.), इह् 1 A, आकांक्ष् 1 U, अभिलष् 1, 4 P, oft. ex. by desid. of roots. 2 अर्थ् 10A, याच् 1A, वृ 5U. **-s.** इच्छा, अभिलाषः, कामः, ईहा, आकांक्षा, समीहितं, आशा, इष्टं, ईप्सितं, मनोरथः, स्पृहा, अभीष्टं; 'according to one's d.' यथाकामं, यथेष्टं, स्वेच्छातः, स्वच्छंदं, स्वरुच्या; 'ardent d.' लालसा, औत्सुक्यं, उत्कंठा, लोभः, तृष्णा. **-able,** *a.* स्पृहणीय, काम्य. 2 इष्ट, प्रशस्त, श्रेयस्. **-ous,** *a.* सस्पृह, वांछिन्, इच्छु, ईप्सु; oft. by desid. forms, 'd. to speak.' विवक्षुः; 'd. to take' जिघृक्षुः; or by काम or मनस् in comp. with inf.; 'd. to take' आदातुकामः-मनाः.

Desist, *v. i.* विरम् 1 P, निवृत् 1 A, विश्रम् 4 P, (with abl.); *See* **Cease. -ance,** *s.* विरामः, निवृत्ति *f.*, विश्रामः.

Desk, *s.* लिखनफलकः. लेखनाधारः.

Desolate, *a.* निर्मानुष (षी *f.*), निर्जन, शून्य, विविक्त, वसतिहीन, विजन. 2 उच्छिन्न, जीर्ण, उद्ध्वस्त, उत्सन्न. 3 असहाय, निराश्रय, अगतिक, अनाथ. **-v. t.** उच्छिद् 7 P, अवसद् c., निर्जनीकृ 8 U, उपपीड् 10, शून्यीकृ, प्रबाध् 1 A. **-ion,** *s.* उच्छेदः, अवसादनं, वसतिनाशः, निर्जनीकरणं. 2 शून्यता, निर्जनत्वं, विविक्तता.

Despair, *v. i.* निराशः *a.* भू 1 P, आशां हा 3 P, नैराश्यं गम्-व्रज् 1 P, विषद् 1 P, भग्नाश *a.* भू; 'd.ed. of success' जयविषये निराशीभूत. **-s.** नैराश्यं, निराशता, आशाहीनता, वैक्लव्यं, विषादः; 'being in d.' त्यक्ताश, गताश. **-Desperate,** *a.* निराश, आशातीत, त्यक्ताश, आशाहीन. 2 जीवितनिरपेक्ष, आततायिन्, निर्भय, साहसिक (की *f.*) 3 निष्प्रतीकार, उग्र, संरब्ध, साहसद्योतक, अत्यंत; 'a d. act' साहसं, आततायिता. **-ly,** *adv.* जीवितनिरपेक्षं, प्रसह्य, उग्रं, उन्मत्तवत्. 2 अति-सु pr.; अत्यंतं, भृशं. **-ness,** साहसिकता, उन्मादः, संरंभः जीवितनिरपेक्षता.

Despatch, *v. t.* (सत्वरं) प्रेष् c., प्रहि 5 P. प्रस्था c. (स्थापयति), विसृज् 6 P. 2 शीघ्रं, झटिति संपद् c.; त्वर् c. (त्वरयति), आशु संविधा 3 U. 3 हन् 2 U, व्यापद् c.; *See* **Kill.** **-s.** त्वरा, शीघ्रता, शीघ्रकारित्वं, अदीर्घसूत्रता. 2 पत्रं, राजलेखः-लेख्यं, वार्त्तिकपत्रं. 3 धावकः, प्रजाविन् *m.*, वार्ताहरः, दूतः. **-ful,** *a.* त्वराशील, शीघ्रकारिन्, अविलंबिन्, अदीर्घसूत्र.

Desperado, *s.* साहसिकः, प्रसह्यचौरः, साहसिन् *m.*, आततायिन् *m.*, वधोद्यतः.

Despise, *v. t.* अवज्ञा 9 U, तिरस्कृ 8 U, अवमन् 4 A, परिभू 1 P, अवधीर् 10; *See* **Contemn. -er,** *s.* अवमंतृ *m.*, अवज्ञातृ *m.*, निंदकः. **-ingly,** *adv.* सावज्ञं, सावमानं. **-Despicable,** *a.* अवमान्य, अवज्ञेय, गर्ह्य, निंद्य, नीच, निकृष्ट, अधम, तुच्छ, कुत्सित, क्षुद्र.

Despite, *s.* द्वेषः, जुगुप्सा, मात्सर्यं, ईर्ष्या, अभ्यसूया, असूया. 2 प्रतिरोधः, प्रतिकारः; 'in d. of' (prep.) अनादृत्य, अवगणय्य, or gen. abs.; 'd. the (presence of the) teacher' पश्यतोपि गुरोः; *See* 'in spite of' under **Spite. -ful,** *a.* द्वेषिन्, सासूय, अभ्यसूयक, मत्सरिन्, द्रोहबुद्धि. **-fully,** *adv.* सद्वेष, सद्रोहं, ईर्ष्यया. **-fulness,** *s.* मात्सर्यं, असूया. दौर्जन्यं, द्रोहः, द्रोहबुद्धि *f.*

Despoil, *v. t.* हृ 1 P, अपहृ; *See* **Deprive;** 'd. ed of everything' हृतसर्वस्व. **-er,** *s.* अपहारकः. **-Despoilation,** *s.* अपहरणं.

Despond, *v. i.* निर्विद् 4 A, नैराश्यं-निर्वेदं-विषादं-गम् 1 P or आपद् 4 A, विषद् 1 P, आशां त्यज् 1 P, अंगानि मुच् 6 P. **-ency,** *s.* निर्वेदः, विषादः, नैराश्यं, उद्वेगः, अवसादः, विषण्णता. **-ent, -ing,** *a.* निर्विण्ण, विषण्ण, निराश, त्यक्ताश, म्लान, उद्विग्न; 'do not take a d. view' मा भवानंगानि मुंचतु (V. 2). **-ingly,** *adv.* सविषादं, सनिर्वेदं.

Despot, *s.* प्रजापीडकः, लोकोपप्लवकः, 2 अधीश्वरः, सम्राज् *m.*, सार्वभौमः, चक्रवर्तिन् *m.* **-ic, -ical,** *a.* स्वतंत्र, निष्प्रतिबंध, अनियंत्रण, अनियत, निर्यंत्रण. **-ically,** *adv.* स्वैरं, स्वेच्छातः, कामचारेण. **-ism,** *s.* प्रजापीडनं, निष्ठुरशासनं, प्रजोपप्लवः. स्वेच्छाचारित्वं, स्वेच्छाप्रभुत्वं; निर्यंत्रणाराज्यसरणिः *f.*

Despumate, *v. i.* उत्सिच् pass., फेनायते (D.)

Dessert, *v. t.* (भोजनांते) फलाहारः.

Destine, *v. t.* (**Destinate**) निरूप् 10, परि-प्र-क्लृप् c., निर्दिश् 6 P, नियुज् 7 A, 10.

समुपस्था 1 U, (न जाने भोक्तारं कमिह समुपस्थास्यति विधिः S. 2); oft. ex. by pot. pass. part., with or without अवश्यं, नूनं; 'he is d.ed to be a king' अनेनावश्यं राज्ञा भवितव्यं; 'man is d.ed to die' मनुष्या नश्वराः; 'who is able to avoid what is d.ed for him' लिखितमपि ललाटे प्रोज्झितुं कः समर्थः; तथा भवितव्यतया च तस्य तस्य वस्तुनः (Ka. 143) 'every thing being d.ed to occur' &c. -ation, s. ईप्सितं स्थानं, इष्टः प्रदेशः, निरूपित-निर्दिष्ट-स्थानं. 2 उपयोगः, प्रयोजनं, उद्देशः; अर्थः, अभिप्रायः. -y, s. दैवं, भवितव्यता, नियति, f., भाग्यं, भागधेयं; विधातृ m., विधिः, दिष्टं, अदृष्टं, प्राक्तनं.

Destitute, a. निर्धन, अर्थहीन, निराश्रय, दुर्गत, अशरण, दीन, अकिंचन, दुःस्थित. 2 (of) हीन, रहित, वर्जित, शून्य, वियुक्त, लुप्त, विहीन, परिहीण, with instr. or in comp.; gen. by निर्-अ-वि- in comp; 'd. of courage' धैर्यहीन-शून्य, &c.; निरुत्साह 'd. of energy'; 'd. of hands and feet' अपाणिपाद. -ion, s. दैन्यं, धनाभावः, अकिंचनत्वं, दारिद्र्यं, निराश्रयता. 2 हीनत्वं, राहित्यं, शून्यत्वं, अभावः, विरहः, वियोगः.

Destroy, v. t. नश् c, प्र-वि°, अव-उद्-सद् c., ध्वंस् c., प्र-वि°; विलुप् c., क्षै c. (क्षपयति), क्षि 5 P or c., संहृ 1 P, उत्-निर्-मूल् c, उच्छिद् 7 P, प्रतिहन् 2 P. 2 (persons &c.) हन् 2 P, निषूद् 10, व्यापद् c., मृ c.; 'to be d.ed' वि-, नश्, 4 P, ध्वंस् 1 A, क्षयं या-इ 2 P, or गम् 1 P, प्र-वि-ली 4 A. -er, s. नाशकः, हंतृ m., निषूदनः, घातिन् m., अंतकः, ध्वंसकः, हन्-अपह in comp, 'd. of Vritra' वृत्रहा, वृत्रनिषूदनः; 'd. of every thing' कृतांतः. -Destructible, a. नश्वर, विध्वंसिन्, भंगुर, क्षयिन्. -Destruction, s. नाशः, विनाशः, प्रणाशः; प्र-, वि-, ध्वंसः, क्षयः, उच्छेदः, संहारः; उद्दलनं, उत्पाटनं. 2 निषूदनं, घातः, वधः; 'd. of the whole world' प्रलयः, प्रत्यवहारः, कल्पांतः, संवर्तः. -Destructive, a. विनाशोन्मुख, क्षयकर (री f.), घातिन्, अंतकर, घातुक, अपह-घ्न (घ्नी f.) in comp.: 'd. to life' जीवितापह, प्राणहर, निधनकारिन्.

Desuetude, s. विरति f., निवृत्ति f., विच्छेदः, विरामः, प्रवृत्तिविच्छेदः.

Desultory, a. असतत, उच्छृंखल, अस्थिर, लोल, अनियत, चंचल, अनवस्थित, अव्यवस्थित.

Detach, v. t. विश्लिष् c., विभिद् 7 P, विच्छिद् 7 P, वियुज् 7 A, 10, पृथक् कृ 8 U; *See Separate*. -ed, a. वियुक्त, विभिन्न, विच्छिन्न; असंसक्त, असंलग्न, पृथक्, विश्लिष्ट, असंयत. -ment, s. विभागः, वियोगः, विच्छेदः, विश्लेषः, विभेदः. 2 सैन्यदलं, गुल्मः-ल्मं.

Detail, s. विस्तरः, विस्तारः; वाग्विस्तरः, प्रपंचः. 2 वृत्तांतकथनं; 'in d.' or 'd.ed' सविस्तर (a.), विस्तरेण, विस्तरतः-शः, सविस्तरं. -v. t सविस्तरं-विस्तरेण-वर्ण् 10 or आख्या 2 P. or कथ् 10, प्रपंचयति (D.).

Detain, v. t. धृ 1 P, निरुध् 7 U; जामातृयज्ञेन वयं निरुद्धाः (U. 1) 'd.ed by reason of' &c. 2 निवार् 10, निग्रह् 9 P. 3 (in custody) आसिध् 1 P, बंध् 9 P, निरुध्. -Detention, s. धरणं, निग्रहः, संरोधः, निरोधः. 2 आसेधः, प्रति-नि-रोधः, बंधनं, बलात्कारेण धरणं.

Detect, v. t. निरूप् 10, ज्ञा 9 U, अनुसंधा 3 U, अधि-अव-गम् 1 P; दृश् 1 P, उपलभ् 1 A, आसद् c. 2 धृ 1 P, प्रकाश् c., व्यंज् 7 P; 'd.ed in a crime' दृष्टदोष; निर्णीतापराध. -ion, s. ज्ञानं, निरूपणं, अनुसंधानं, उपलंभः, अवगमनं -ive, a. (Officer) चरः, चारः, प्रणिधिः, अपसर्पः; *See Spy*

Deter, v. t. (सभयं) निवृत् c., निवार् 10, विरम् c. (रमयति), भी c., निरुध् 7 U; *See* **Prevent.** -ment, s. निवर्तनं, निवारणं.

Deterge, v. t. शुध् c., मलं अपनी 1 P, परिमृज् 2 P. -ent, a. शोधन (नी f.), परिमार्जक.

Deteriorate, v. i. क्षि-हा pass., ह्रस् 1 P, क्षयं गम् 1 P; दुष् 4 P, भ्रंश् 4 P, 1 A, अपकृष् pass. -v. t. अपकृष् 1 P, दुष् c. (दूषयति), विकृ 8 U, ह्रस् c. -ion, s. क्षयः, अपचयः, विकारः, विकृति f., ह्रासः, भ्रष्टता. 2 अपकर्षः, दूषणं.

Determine, v. t. निश्चि 5 U, स्था c. (स्थापयति), संक्लृप् c., निरूप् 10, निर्णी 1 P, निर्-अव-धृ 10, निर्दिश् 6 P, लक्ष् 10, परिच्छिद् 7 P. 2 निरूप्, अनुसंधा 3 U, निर्णी (a dispute &c.). -v. i. व्यव-अव-सो 4 P, निश्चयं कृ 8 U; 'd.ed to go' गमने कृतसंकल्प, गंतुं व्यवसित. -ate, a. स्थिर, दृढ, निर्धारित, निश्चित, निर्णीत. नियत, सिद्ध, व्यवस्थित. 2 निश्चायक, निर्णायक. 3 (of persons) कृतनिश्चय, दृढसंकल्प, व्यवसित. -ately, adv. सनिश्चयं, सनिर्णयं, नूनं. -ation, s. निश्चयः, निर्णयः, संकल्पः, निर्धारणं, व्यवसायः, विचारः निरूपणं, परिच्छेदः, अवधारणं-णा. 2 अभिनिवेशः, अध्यवसायः, निर्बंधः. -ative, a. निर्णायक, निर्धारक. -ed, a. निश्चित, निर्णीत, सिद्ध, नियत, व्यवस्थित, परिच्छिन्न, अवधारित. 2 (of persons) स्थिरनिश्चय, दृढ-कृतसंकल्प, अभिनिविष्ट, कृतनिश्चय. -edly,

adv. स्थिरचेतसा, दृढं, दृढनिश्चयेन. **-er,** *s*. निर्णयकृत् *m*., निर्णेतृ *m*.

Detest, *v. t*. विद्विष् 2 U, गर्ह् 1, 10 A, गुप् desid. (जुगुप्सते) (with abl.); *See* **Abhor. -able,** *a*. जुगुप्सित, गर्हित, निंद्य, गर्हणीय, विद्वेष्य. **-ation,** *s*. गर्हा, जुगुप्सा, घृणा, विद्वेषः. **-er,** *s*. द्वेषिन् *m*., विद्वेष्टृ *m*.

Dethrone, *v. t*. राज्यात् भ्रंश् c. or च्यु c. or अवपत् c. or अवरुह् c. (रोपयति). **-ment,** *s*. राज्यभ्रंशः-च्युति *f*.

Detonate, *v. i*. सहसा स्तन् 1 P or ध्वन् 1 P. **-ion,** *s*. स्तनितं, आकस्मिकध्वनि *m*.

Detort, *See* **Pervert.**

Detract, *v*. अपकृष्-अपनी 1 P. **2** अपलप् 1 P, अपवद्-भाष् 1 A, अधिक्षिप् 6 P, निंद् 1 P, असूयति (D.) (with dat.), मूल्यं न्यूनीकृ 8 U; लघूकृ; *See* **Depreciate. -ion,** *s*. अपकर्षः, लघूकरणं, ह्रासः. **2** असूया, अप-परि-वादः, आक्षेपः, गुणनिंदा, पैशुन्यं, परदोषाविष्करणं, मात्सर्यं. **-or,** *s*. अपवादकः, अधिक्षेपकः, निंदकः, असूयकः, परिवादरतः. **-ory,** *a*. अपवादिन्, निंदक, अभ्यसूयक; पिशुन.

Detriment, *s*. हानि *f*., अपकारः, क्षति *f*., नाशः, अपायः बाधा, विरोधः. **-al,** *a*. हानिकर (री *f*.), विरोधिन्, अपायकारक.

Detrude, *v. t* अवपत् c, अधः क्षिप् 6 P, भ्रंश् c. **-Detrusion,** *s*. अवपातनं.

Detruncate, *v. t*. अवच्छिद् 7 P, निकृत् 6 P, वि-लू 9 U. **-ion,** *s*. अवच्छेदः, निकर्तनं.

Deuce, *s*. द्वयं, द्विकं. **2** पिशाचः, भूतः.

Devastate, *v. t*. उच्छिद् 7 P, उत्-अव-सद् c.; उपपीड् 10, वि-उप-द्रु 1 A, प्रबाध् 1 A, निर्जनीकृ 8 U. **-ion,** *s*. उच्छेदः, उपप्लवः, प्रबाधनं, विनाशः, निर्जनीकरणं.

Develop, *v. t*. पुष् 1, 4, 9 P, प्र-उप-चि 5 U, प्र-सं-वृध् c.; 'she d ed her lovely limbs' पुपोष लावण्यमयान् विशेषान् (K. I. 25): also प्रकाशमानावयवा R. III. 7) उपचितांगी. **2** विकस् c., विस्तृ c., उद्भिद् c.; तस्य (कार्यपक्षस्य) विस्तारमिच्छन् (Mu. 4) 'wishing to d. it.' **-v. i**. प्र-उप-चि pass., उद्भिद् pass., क्रमशः विकस् 1 P, क्रमेण प्र-सं-वृध् 1 A. **-ment,** *s*. प्रचयः, उपचयः, संवर्धनं; विस्तारः, विकासः, उद्भवः.

Devergence, *See* **Divergence.**

Deviate, *v. i*. अति-व्यति-इ 2 P, अतिक्रम् 1 U, 4 P, अति-व्यभि-चर् 1 P; 'did not d. even an inch from the beaten path' क्षुण्णाद्वर्त्मनो रेखामात्रमपि न व्यतीयुः (R. I. 17); अप-या-इ 2 P, चल् 1 P, प्र-वि-°, च्यु 1 A, भ्रंश् 4 P, 1 A, (with abl.). **-ion,** *s*. अतिक्रमः, विचलनं, च्युति *f*., भ्रंशः, व्यभिचारः, त्यागः; 'd. from the right path' उत्पथयानं, विमार्गगमनं.

Device, *s*. उपायः, युक्ति *f*., प्रयोगः, कल्पना, साधनं. **2** अप-व्यप-देशः, छलं, माया, छद्मन् *n*., कैतवं, व्याजः. **3** लक्षणं, चिह्नं, अंकः. **4** निर्माणशक्ति *f*., कल्पनाचातुर्यं.

Devil, *s*. भूतः, वेतालः, पिशाचः; 'I shall not raise a d. for my own destruction' नाहमात्मविनाशाय वेतालोत्थापनं करिष्यामि.

Devious, *a*. वक्र, कुटिल, जिह्म. **2** मर्यादातिक्रमिन्, व्यभिचारिन्.

Devise, *v*. चिंत् 10, उप-सं-क्लृप् c., निरूप् 10, युज् 7 U, 10. आ-पर्या-लोच् 10, घट् c. **2** इच्छापत्रेण प्रदा 3 U. **-s.** इच्छापत्रेण रिक्थदानं. **-er,** *s*. धनाधिकारिन्, *m*. **-er,** *s*. उपायज्ञः, परिकल्पकः, प्रयोजकः.

Devoid, (of), *a*. *See* **Destitute (of).**

Devoir, *s*. स्वकर्तव्यं, कर्तव्यता, धर्मः. **2** सत्कारः, आदरः, पूजा, संमानः.

Devolve, *v. t*. निक्षिप् 6 P, न्यस् 4 P, संक्रम् c., सम्-ऋ c. (अर्पयति), आरुह् (रोपयति) 'having d. ed their property upon their sons' पुत्रसंक्रांत[illegible]काः (U. 1); गुणवत्सुतरोपितश्रियः (R. VIII. 11). **2** प्रपत् c., प्रसु-प्रवह् c. **-v. i**. आगम् 1 P, आया 2 P, पत् 1 P, [illegible] 1 U, 4 P; न्यस् निक्षिप्-सम् c. pass.; 'after his death the king[illegible] d. ed upon his eldest son' मृते तस्मिंस्तस्य ज्येष्ठपुत्रो राजपदभाग्बभूव. **2** अधः पत् 1 P, अवपत्. **-Devolution,** *s*. निक्षेपणं, समर्पणं, संक्रामणं.

Devote, *v. t*. प्र-विनि-युज् 7 A, 10, सम् ऋ c. (अर्पयति), निक्षिप् 6 P, उत्सृज् 6 P, सं-उप-क्लृप् c. **2** (Oneself to) आसंज् अनुरंज्- pass., मनः युज् or बंध् 9 P or अभिनिविश् c., आसक्त-अभिनिविष्ट *a*. भू (all with loc.): भज् 1 U, आसेव् 1 A. **3** नाशाय क्लृप् c; *See* **Doom. -ed,** *a*. सक्त, आ-प्र-व्या-सक्त; नि-, रत, अभिनिविष्ट, समाहित, पर-तत्पर-परायण in comp. **2** भक्त, दृढभक्ति, अनुरक्त, अनुरागिन्; 'd to the king' राजनिष्ठ, नृपासक्तचित्त; 'a d. wife' एकपत्नी, पतिव्रता, साध्वी, सती, 'a d. husband' भार्यानिरतः, पत्नीसेविन् *m*. 'a d. friend' स्थिरप्रेम मित्रं, दृढसखः सुहृद् **-edly,** *adv*. चित्तकाग्रतया, भक्त्या, निष्ठया, अभिनिविष्टं, मनोभिनिवेशेन, मनोयोगेन, सुसमाहितं. **-edness,** *s* आसक्ति *f*., भक्ति *f*., अभिनिवेशः, परायणता. **-ee,** *s*. तापसः, यतिः, योगिन् *m*., तपस्विन् *m*., मुनिः, व्रतिन् *m*. **2** भक्तजनः. प्रणयिजनः, उपासकः, भक्तः. **-ion,** *s*. अभियोगः, अभिनिवेशः, अनुरागः,

सेवा, उपासना, प्रसक्ति *f.*, आसक्ति *f.* भक्तिः, निरति *f.*, परायणता. 2 नियमः, धर्मक्रिया, तपस् *n.* ईश्वरभक्ति *f.* सेवा; 'self-d.' आत्मोत्सर्गः-परित्यागः; 'd. to a husband' पातिव्रत्यं, पतिसेवा; 'to perform d. s' तपश्चर् 1 P or तप् 4 A, तपस्यति (D.). **-ional,** *a.* धर्मपर. धर्मनिष्ठ, भजनशील. 2 धर्मक्रियाविषयक, तपोमय (यी *f.*).

Devour, *v. t.* भक्ष् 10, अद् 2 P, खाद् 1 P, ग्रस् 1 A, गॄ 6 P. 2 उपयुज् 10, उपयोगेन विनश् c. **-er,** *s.* भक्षकः, खादकः.

Devout, *a.* धार्मिक, धर्म-परायणशील, धर्मनिष्ठ, धर्मात्मन्, भक्त, ईश्वरनिरत, पुण्यशील, प्रयतात्मन्, पुण्यात्मन्. **-ly,** *adv.* भक्त्या, भक्तिपूर्वकं, भक्तिपुरःसरं, श्रद्धान्वितं. **-ness,** *s.* धार्मिकता, धर्मात्मता, ईश्वरनिष्ठता, भक्ति *f.*

Dew, *s.* नीहारः, अवश्यायः, तुषारः, प्रालेयं, हिम-रात्रि-ख-जलं. **-v. t.** नीहारेण सिच् 6 P or प्रोक्ष् 1 P; 'd. drop' तुषारकणः-बिंदुः-शीकरः, and sim. comps. **-y,** *a.* तुषारमय (यी *f.*), अवश्यायावसिक्त; तुषारकणोपम.

Dexterous, *a.* कुशल, निपुण, पटु, दक्ष, लघुहस्त, करदक्ष. **-ly,** *adv.* निपुणं, दक्षतया, सपाटवं, हस्तलाघवेन. **-Dexterity,** *s.* दक्षता, पटुता, नैपुण्यं, हस्तकौशलं, हस्तलाघवं.

Dextral, *a.* दक्षिण, अपसव्य, दक्षिणपार्श्वस्थ.

Diabetes, *s.* मधुमेहः, प्रमेहः, बहुमूत्ररोगः.

Diabolical, *a.* पैशाच (ची *f.*), पिशाचोपम. 2 घोर, दारुण, पापिष्ट, अतिघोर-पाप, अतिनिंद्य.

Diacoustics, *s.* स्वनिविद्या.

Diadem, *s.* मुकुटं, किरीटः-टं, मौलिः, उष्णीषः-षं, शिरोवेष्टनं, 'd. ed' किरीटिन्, किरीटधारिन्.

Diagnosis, *s.* रोगनिर्णयः-निरूपणं, रोगनिदानं, मीमांसा, चिकित्सा.

Diagnostic, *s.* रोगलक्षणं-चिह्नं.

Diagonal, *s.* कर्णः, श्रुति *f.* **-ly,** *adv.* कोणाकोणि, कर्णाकर्णि.

Diagram, *s.* चित्रं.

Dial, *s.* शंकुयंत्रं, सूर्यघटी.

Dialect, *s.* प्राकृतभाषा, भाषा (as opposed to संस्कृत). 2 भाषणं, वचनं, उक्ति *f.*

Dialectic, *s.* तर्कः, न्यायः, हेतुविद्या, आन्वीक्षिकी विद्या. **-al,** *a.* तार्किक (की *f.*), न्यायिन्. **-ian,** *s.* तार्किकः, नैयायिकः, न्यायविद् *m.*

Dialogue, *s.* संलापः, संवादः, संकथा, संभाषणं, प्रश्नोत्तरं, कथोपकथनं. **-Dialogist,** *s.* संवादकः, उत्तरप्रत्युत्तरदायकः.

Diameter, *s.* व्यासः, विष्कंभः. **-Diametrically,** *adv.* विपरीतं, प्रतिकूलं, अत्यंतं, एकांततः.

Diamond, *s.* वज्रः-ज्रं, हीरं, हीरकः; 'd. cutter' हीरकारः-मार्जकः

Diapason, *s.* स्वराष्टकं, स्वरग्रामः.

Diaper, *s.* चित्रितं क्षौमं. **-v. i.** क्षौमं चित्र् 10 or कर्बुरीकृ, &c.

Diaphanic, *a.* स्वच्छ, विशद; *See* **Clear.**

Diaphoretic, *a.* स्वेदन (नी *f.*), स्वेदजनक, घर्मोत्पादक; 'd. medicine' स्वेदनं.

Diaphragm, *s.* शरीरमध्यदेशः.

Diarrhœa, *a.* अतिसारः, प्रवाहिका; ग्रहणी-, रुज् *f.*

Diary, *s.* दिनपत्रिका, दैनिकवृत्तपुस्तकं.

Diatribe, *s.* अधिक्षेपः, कुत्सात्मको लेखः.

Dibble, *s.* लघुखनित्रं.

Dice, *s.* plural of **Die,** *s.* q. v.

Dictate, *v. t.* आज्ञापूर्वकं कथ् 10. आदिश् 6 P, आज्ञा c. (ज्ञापयति). 2 चुद् 10, प्रोत्सह् c., प्रचुद् 10, प्रेर् c.; 'd. ed by good motives' सदाशयप्रेरित. **-s.** आज्ञा, आदेशः, शासनं. 2 चोदनं-ना, प्रेरणं-णा. **-ion,** प्रोत्साहनं. 2 आज्ञापनं, आज्ञापूर्वकं कथनं. **-or,** *s.* एकाधिपतिः, अनन्याधीनः शास्ता, अनियंत्रणः प्रभुः. 2 आदेशकः, शासितृ *m.* **-orial,** *a.* अवलिप्त; *See* **Arrogant.**

Diction, *s.* भाषा, वाणी, वाक्सरणि *f.*, वचोविन्यासः.

Dictionary, *s.* कोशः-षः, शब्दसंग्रहः; अभिधानं.

Dictum, *s.* वचनं, आदेशः, विधिः, नियमः.

Didactic,-al, *a.* उपदेशपर, प्रबोधक.

Die, *s.* अक्षः, पाशकः, देवनः; 'a loaded d.' कूटाक्षः. **-Dice,** (pl.) अक्षाः, &c. **-v. i.** अक्षैः दिव् 4 P, ग्लह् 1 P. **-er,** *s.* अक्षधूर्तः, अक्षदेविन् *m.*, धूर्तः, कितवः. **-ing,** *s.* द्यूतं, अक्षक्रीडा; 'd. board' अष्टापदं, शारिफलं; 'd. box' अक्षाधारः; 'the die is cast' कृतं दैवाधीनं (अप्रतिविधेयं) कर्म, अधुना यद्भावि तद्भवतु.

Die, *v. i.* मृ 6 A, प्राणान्-असून्-जीवितं त्यज् 1 P or उत्सृज् 6 P or हा 3 P, पंचत्वं या 2 P or गम् 1 P, उपरम् 1 P; परासु-गतासु-*a.* भू 1 P, देहं-तनुं त्यज्, प्र-इ 2 P, विपद् 4 A, संस्था 1 A, प्रमी pass. 2 विनश् 4 P, म्लै 4 A, ध्वंस् 1 A क्षि pass., अवसद् 1 P. 3 ग्लै 1 P, विद्रा pass. **-Dead,** *a.* मृत, उपरत, संस्थित, प्रेत, पंचत्व, परासु, गतासु, विपन्न, गतप्राण, विचेतन. प्राणहीन, प्रमीत. 2 निश्चल, निश्चेष्ट, जड, निस्तेजस्, निःसत्व, असार, निष्फल. 3 सुप्त, स्तब्ध (as of limbs); 'd. body' शवं, मृतशरीरं; कुणपः. 'd. language' अप्रचलिता भाषा; 'd. sleep' घोर-गाढ-निद्रा; 'd. loss' परिपूर्णा -सकला हानिः; 'd. letter' लुप्तार्थं वचनं, 'd. soul' निरभिमानः आत्मा. **-s.** (Of night) मध्यरात्रः, निशीथः, अर्धरात्रः. 2 मध्यं; *See* **Depth.** **-en,** *v. t.* दुर्बलीकृ. 8 U, शिथिलीकृ, तेजो हृ 1 P, नश् c.,

म्लानीभू. -*v. i.* म्लै 1 P, शिथिलीभू. -**ly,** *a.* प्राणापहारक, जीवितापह, मारात्मक, निधनकारिन्, प्राणांतक, प्राणहारिन्, प्राणनाशक, जीवितघ्न (घ्नी *f.*). **2** अशाम्य; 'd. enmity' आमरणांतिकं वैरं, अशाम्यं वैरं; 'd. poison' हाला(ल)हलं विषं. -*adv.* मृतवत्; प्राणांतिकं; 'd. wounded' भिन्नमर्मन्; 'd. pale' प्रेतसवर्ण. -**ness,** *s.* दौर्बल्यं, निःसत्वता, जडत्वं, स्तंभः; वैकल्यं, विरक्ति, *f.*, शिथिलता. -**Death,** *s.* मरणं, मृत्युः, उपरमः, निधनः-नं, अंतः, पंचत्वं-त्ता, संस्थिति *f.*, कालधर्मः, दिष्टांतः, प्रलयः, अत्ययः, नाशः, प्राणनाशः, तनुत्यागः, &c. **2** यमः, कालः, कृतांतः. **3** वधः, घातः, व्यापादनं; 'he was pelted to d.' सलोष्टघातं हतः; 'he was sentenced to d.' तस्य प्राणदंड आदिष्टः; 'to put to d.' हन् 2 P, व्यापद् c., वधं आदिश् 6 P; 'a violent d.' अपमृत्युः ; अपघातः; 'angel of d.' यमदूतः; 'd. by fasting' प्रायः, प्रायोपवेशनं; 'd. bed' मृत्युशय्या. -**less,** *a.* अमर, अनश्वर, अमर्त्य, चिरस्थायिन्.

Diet, *s.* आहारः, अन्नं, भोजनं, भक्ष्यं. **2** पथ्यं, पथ्यान्नं., पथ्याशित्वं. **3** राजसभा, शिष्टसभा. -*v. t.* पु c., भृ 3 U. **2** पथ्यं निर्दिश् 6 P.

Differ, *v. i.* भिद् pass., प्र-वि-°; विशिष् pass., (न कारणात्स्वाद्बिभिदे कुमारः R. v. 35); gen. ex. by (*s.*); 'they two do not d.' न तयोर्भेदः, विशेषः, &c. **2** अन्यथा मन् 4 A, न संमन्, विवद् 1 A, भिन्नमत *a.* भू, विप्रतिपद् 4 A, (एवं हि विप्रतिपन्नाः प्राणेभ्यस्तां प्रति श्रुतयः S. B. 702); 'I d. from you' मम मतं त्वन्मताद्भिन्नं. **3** विप्रति-रुध् pass. -**ence,** *s.* भेदः, विशेषः, अंतरं, (with gen.). **2** पार्थक्यं, इतरत्वं, भिन्नत्वं, व्यतिरेकः; 'that makes no d.' तेन न कोपि विशेषो जायते. **3** विरोधः, वैपरीत्यं, विपर्ययः, वैलक्षण्यं. **4** विप्रतिपत्ति *f.*, मतिभेदः, विसंवादः, वैमत्यं; कलिः, कलहः, विवादः. **5** असाम्यं, असादृश्यं; 'd. in quantity' वैषम्यं. -**ent,** *a.* भिन्न, वि-प्र-भिन्न, इतर-अन्य-पर-*pron. a.*, व्यतिरिक्त, विपरीत, पृथक्, विशिष्ट, (with abl.); अंतर in comp.; 'she is not d. from my body (myself)' अव्यतिरिक्तेयमस्मच्छरीरात् (Ka. 151); 'a d. sense' अर्थांतरं. **2** असदृश (शी *f.*), असमान, विषम, असम. **3** विविध, नानाप्रकार, नाना in comp.; तत्तत् *pron. a.*, 'd. S'âstras' तानि तानि शास्त्राणि; 'in a d. way' अन्यथा, भिन्नप्रकारेण. -**ential,** *a.* भेदकर (री *f.*), विशेषक. -**ently,** *adv.* अन्यथा, इतरथा, भिन्नरूपेण; अन्यप्रकारेण, पृथक्.

[Dif]**ficu**[lt,] *a.* असुकर, दु[ष्क]र, कठिन, दुष्कर, दुःसाध्य, कष्ट. **2** गहन, विषम, दुर्बोध, असुगम, कष्टज्ञेय गूढार्थ, दुर्ज्ञेय. **3** (With inf.) ex. by दुर्, दुःख, कष्ट, in comp.; 'd. to get दुष्प्राप, दुराप, कष्टसाध्य; दुरारोह, दुःखछेद्य, &c.; 'a d. case' सशल्योऽर्थः; 'a d. road' दुर्गसंचा(च)रः, संक्रमः; 'a d. place' विषमस्थानं, दुर्गं, दुर्गमस्थलं. -**ly,** *adv.* दुःखेन, कष्टेन, कृच्छ्रेण, कष्टं, आयासेन, दुर्, pr. -**y,** *s.* असौकर्यं, वैषम्य, कठिनता, दुष्करत्वं, कष्टता, दुःसाध्यता. **2** आयासः, वैक्लव्यं, विरोधः. **3** कृच्छ्रं, संकटं, विघ्नः, आयासः, दुर्गं, दुःखं, विरोधः, क्लेशः, बाधा, कष्टः-ष्टं. **4** विषमपदं, असुबोधं-दुर्बोधं पदं, असुगमं स्थानं; 'without d.' अनायासेन, सुखं; 'with d.' कथमपि, कथं कथमपि, कथंचित्, दुःखेन, कृच्छ्रेण; 'a commentary explaining the d. es' विषमपदविमर्शिनी टीका; 'beset with d. es' सशल्य, सकंटक; 'overcoming d. es' दुर्गलंघनं.

Diffidence, *s.* अविश्वासः, अप्रत्ययः, आ-, शंका. **2** (In oneself) अप्रगल्भता, विनयः, ह्रीः, लज्जा. -**Diffident,** *a.* अविश्वासिन्, शंकाशील, अप्रत्यय, साशंक; 'the mind feels d. of itself' आत्मन्यप्रत्ययं चेतः (S. 1). **2** अप्रगल्भ, अधृष्ट, विनीत, ह्रीमत्, लज्जावत्. -**ly,** *adv.* अप्रगल्भं, साशंकं, लज्जया, सविनयं.

Diffract, *v. t.* वियुज् 7 A, 10, विश्लिष् c.

Diffuse, *v. t.* प्रसृ c., वि-परि-स्तृ c., विसृप् c., प्रचर् c. विकॄ 6 P, तन् 8 U, अभि-प्र-वृध् c. **2** प्र-स्नु c., विद्रु c., प्रक्षिप् P. **3** (Itself) व्याप् 5 P, विसृ-विसृप् 1 P, विस्तॄ pass., व्यश् 5 A, सर्वत्र गम् 1 P. or प्रविश् 6 P. -*a.* वितत, सविस्तर, विस्तृत, असंक्षिप्त, विस्तीर्ण, सप्रपंच. -**ly,** *adv.* सविस्तरं, विस्तरेण, विस्तरशः, प्रपंचेन, असंक्षेपतः, असमासेन. -**ion,** *s.* प्रसारः, प्र-वि-सरः, विस्तारः, अभिवृद्धि *f.*, वितति *f.*, प्रचारणं, प्रसरणं. -**ive,** *a.* वि-प्र-सारिन्, व्यापक, व्यापिन्, प्रसरणशील. -**iveness,** *s.* विस्तारः, विस्तृति *f.*, व्यापकत्वं. **2** वाग्विस्तरः, प्रपंचः, वाक्यविस्तरः.

Dig, *v. t.* खन् 1 P; 'd. down' (भूमिं) अवदृ 10, भिद् 7 U; 'd. in' निखन्. **2** निर्भिद्, छिद् 10, व्यध् 4 P. -**ger,** *s.* खनकः, खनितृ *m.*

Digest, *v. t.* (जठरे) जॄ c. (जरयति), पच् 1 P, परिपाकं नी 1 P, परिणम् c. (णमयति), दह् 1 P, **2** क्रमेण-यथाक्रमं-विन्यस् 4 U or रच् 10 or ग्रंथ् 9 P or लिख् 6 P. **3** मनसा विचर् c. or चिंत् 10. **4** suffer, q. v. -*v. i.* जॄ 4 P, पच् pass., परिणम् 1 P. -**er,** *s.* पाचकं, जारणं, अग्निवर्धनं, रोचनं, रोचकं. -**ion,** *s.* पाकः; वि-परि-पाकः, पचनं, परिणामः. **2** जठराग्निः, जठरानलः, अग्निः; 'slowness of d.' अग्निमांद्यं; 'having a

good d.' प्रदीप्ताग्निः. **-ive,** *a.* पाचन (नी *f.*), पाचक, अग्निवर्धक, परिपाकिन्.

Dight, *See* **Adorn.**

Digit, *s.* कला, लेखा, रेखा. **2** अंकः.

Dignity, *s.* महिमन् *m.*, माहात्म्यं, औदार्यं. **2** अनुभावः, प्रतापः, तेजस् *n.*, प्रौढि *f.*, प्रौढत्वं-ता. **3** प्रतिष्ठा, गौरवं, पदं, उत्कृष्ट-परमपदं, उत्कर्षः, उन्नति *f.*, आभिजात्यं, प्रतिपत्ति *f.*, ओजस्विता, उन्नत्वं, कुलीनता; 'd. of style' ओजस् *n.* **4** मानः, अभिमानः, गर्वः, दर्पः; 'd. of expression' प्रौढत्वं वचसां. **-Dignify,** *v. t.* संमन् c., सत्कृ 8 U, पूज् 10. **2** उत्कृष्टपदे नियुज् 7 A, 10, परमपदं प्रा पू c., उत्कर्षं नी 1 P. **-ed,** *a.* महानुभाव, अनुभाववत्, ग(गं)भीर, ओजस्विन्, प्रौढ, महाप्रताप; 'd. in mien' गंभीराकृति. **2** मानिन्, महाशय, महेच्छ. **3** उत्कृष्टपदनियुक्त, प्रतिपत्तिमत्, परमपदारूढ. **-Dignitary,** *s.* मान्यजनः, शिष्टजनः, कुलीनपुरुषः.

Digress, *v. i.* प्रस्तुतं न अनुसंधा 3 U, अप्रस्तुतं वद्-भण् 1 P or वच् 2 P, प्रकृतं-कथायोगं त्यज् 1 P; 'you are d. ing' न त्वया प्रस्तुतमनुसंधीयते. **2** उत्क्रम् 1 U, 4 P, विचल् 1 P, प्रच्यु 1 A, भ्रंश् 1 A, 4 P; *See* **Deviate. -ion,** *s.* प्रकृतत्यागः, अप्रस्तुतानुसंधानं; प्रसंगः, प्रासंगिकं वचनं; 'enough of d.' अलं प्रासंगिकेन or प्रसंगेन, प्रकृतमेवानुसंधीयतां. **2** उत्क्रमः, विचलनं, भ्रंशः, च्युति *f.*, त्यागः. **-ive,** *a.* असन्वित, अप्रस्तुत, अप्रकृत, असंगत, असंबद्ध.

Dike, *s.* सेतुः, सेतुबंधः, पिंडलः, धरणः, कूलकः-कं. **2** कुल्या, परिखा, खातं, प्रणालः-ली.

Dilacerate, *See* **Tear.**

Dilapidate, *v. i.* जॄ 4 P, विनश् 4 P, क्षि-उच्छिद्-pass., अवसद् 1 P. **-***v. t.* उच्छिद् 7 P, अवसद् c., प्रध्वंस् c., क्षि c., विनश् c.; *See* **Destroy. -ion,** *s.* क्षयः, ध्वंसः, नाशः, उच्छेदः, अवसादः.

Dilate, *v. t.* विस्तॄ c., वितन् 8 U, प्र-वि-सृ c., दीर्घाकृ 8 U. **2** (upon) प्रपंचयति (D.), सविस्तरं विवृ 5 U, or व्याचक्ष् 2 A, अति-विवृ. **-***v. i.* वितन्-विस्तॄ-विवृ pass., आततीभू, दीर्घीभू. **-ed,** *a.* वितत, व्यायत; उत्फुल्ल, विकसित. **-ion,** *s.* विस्तारः, वितति *f.*, विस्तरणं, विवृति *f.*; विकासः-सनं. उत्फुल्लता.

Dilatory, *a.* दीर्घसूत्रिन्, दीर्घसूत्र, विलंबिन्, मंद, मंथर, चिरक्रिय, अक्षिप्रकारिन्. **-ly,** *adv.* सविलंबं, मंदंमंदं, कालक्षेपेण. **-ness,** *s.* दीर्घसूत्रता, विलंबः, कालक्षेपः, मांद्यं, कार्यजडता.

Dilemma, *s.* उभयसंभवः, विकल्पः.

Diligent, *a.* उद्योगिन्, व्यवसायिन्, उद्युक्त, सोद्योग, उद्यमिन्, अनलस, अभिनिविष्ट, उद्यम-व्यवसाय-पर, उद्योगतत्पर. **2** (of things), अनवरत, सतत, नित्यप्रवृत्त, प्र-आ-सक्त, अभ्यस्त, प्रसित, अविच्छिन्न. **-ly,** *adv.* प्रयत्नतः, सोद्योगं, सोद्यमं; अनवरतं, प्रसक्तं. **-Diligence,** *s.* उद्यमः, अध्यव-व्यवसायः, उद्योगः, अभियोगः, अभिनिवेशः, प्रयत्नः, अभ्यासः, प्रसक्ति *f.*, उत्साहः. **2** सातत्यं, अविच्छेदः, अविरामः, नैरंतर्यं.

Dill, *s.* सालेयः, मधुरिका.

Dilute, *v. t.* जलेन मिश्र् 10, or संसृज् 6 P, विली c., तनूकृ 8 U, क्षीणीकृ; मिश्रणेन शक्तिं तनूकृ. **-ion,** *s.* जलसंसर्गः, जलमिश्रणं; तनूकरणं. **-Diluent,** *s.* विलयनं, तनूकरणं.

Dim, *a.* मंदद्युति, मंदप्रभ, मलिनकांति, मलिन, निष्प्रभ, निस्तेजस्, सतिमिर. **2** अप्रकाश, अव्यक्त, अस्पष्ट, दुरालोक, दुर्दृष्ट; 'seeing d.-ly' हतदृष्टि, अस्पष्टदृश्; 'of d. understanding' मंदमति, जड-स्थूल-धी-बुद्धि, &c. **-***v. t.* अंधीकृ 8 U, अस्पष्टीकृ, कलुषीकृ, निष्प्रभीकृ, मलिनयति (D.). **-ly,** *adv.* अस्पष्टं, अव्यक्तं, निष्प्रभं, मलिनं. **-ness** *s.* तिमिरं, अस्पष्टता, तेजोहानि *f.*, दुरालोकता, मालिन्यं, अस्पष्टता. **2** स्थूलमतिता, बुद्धिमांद्यं.

Dimension, *s.* प्रमाणं, परिमाणं, मात्रा, मानं, विस्तारः.

Diminish, *v. t.*, *v. i.* *See* **Decrease. -Diminution,** *s.* न्यूनीकरणं, ह्रासः, क्षयः, अपचयः, अवसादः, हानि *f.* **-Diminutive,** *a.* अल्पकाय, क्षुद्र, अल्प, स्तोक, सूक्ष्म, लघु. **2** अल्पार्थ (प्रत्ययः); 'कन् is a d. termination' अल्पार्थे कन्.

Dimity, *s.* दृढं कार्पासवस्त्रं.

Dimple, *s.* कपोलभंगः, गंडतरंगः; कपोलोर्मि *f.* ऊर्मि *f.*, भंगुरता, दंतुरता, भंगः, तरंगः. **-Dimply,** *a.* भंगुर, ऊर्मिमत्, दंतुर.

Din, *s.* कलकलः, निनादः, कोलाहलः, तुमुलरवः, निःस्वनः, उच्चघोषः, तुमुलः. **-***v. t.* (श्रवणपुटं) जर्जरीकृ 8 U, कर्णौ उपहन् 2 P or जर्जरयति (D.); *See* **Stun.**

Dine, *v. i.* भुज् 7 A, आहारं-भोजनं सेव् 1 A, or निर्वृत् c., शरीरस्थितिं कृ 8 U or कल्प् c. **-***v. t.* भुज् c., अश् c. **-Dinner,** *s.* भोजनं, आहारः, अशनं; *See* **Food. 2** उत्सवः, जग्धि *f.*, भोजनोत्सवः.

Ding, *v. t.* झङ्कृयते (D.), नद्-स्वन्-क्वण् 1 P; 'ding dong' घंटानादः-शब्दः; किंकिणीरवः-शब्दः-नादः, सततनादः.

Dingle, *See* **Dale.**

Dingy, *See* **Black.**

Dint, *s.* प्रहारः, आघातः, अभिघातः. **2** बलं, प्रभावः, सामर्थ्यं; 'by d. of' बलेन, प्रभावेण, सामर्थ्यात्, योगेन. **-***v. t.* प्रहारेण अंकू 10 or चिह्न् 10.

Diocesan, *s.* प्रधानधर्माध्यक्षः.

Diorthesis, *s.* वक्रांगचिकित्सा.

Dip, *v. i.* नि-,मस्ज् 6 P (with loc.); अव-वि-गाह् 1 A, प्र-नि-विश् 6 P, आप्लु 1 A, (acc.). 2 व्यापृ 6 A, व्यापृत *a.* भू. **-v. t.** अवगाह् c., मस्ज् c. (मज्जयति), प्रवेश् c. 2 सिच् 6 P, क्लिद् c., आर्द्रीकृ 8 U; 'd. in a business' कृषय व्यापृ or प्रवृत् 1 A; 'd. into books' चुम्ब् 1 P; अल्पशः अधि-इ 2 A. **-s.** निमज्जनं. अवगाहः, प्रवेशः. 2 अवपातः, मज्जनं, आनतिः *f.*

Diphtheria, *s.* मांससंतानिका.

Diphthong, *s.* स्वरद्वय. संयुक्तस्वरः, संध्यक्षरं.

Diploma, *s.* पदवी अधिकार-द्योतकं पत्रं

Diplomacy, *s.* सामन् *n.*, नीति *f.*, दौत्यकर्मन् *n.* 2 राजदूतमण्डलं-समूहः. **-Diplomatical,** *a.* दूतकार्यविषय. **-Diplomatist,** *s.* सामप्रयोगज्ञः., राजनीतिकुशलः, दौत्यकार्यनिपुणः, सामकुशलः

Dipsomania, *s.* मद्यासक्तिः *f.*

Dire,-ful, *a.* दारुण, घोर, उग्र, तीव्र. 2 भीषण, क्रूर, भयानक, रौद्र. **-ness,** *s.* दारुणत्वं, घोरता, रौद्रता.

Direct, *v. t.* संधा 3 U, लक्ष्यीकृ 8 U, उद्दिश् 6 P, प्रेर् c., अधिकृत्य क्षिप् 6 P, (a missile &c.); 'd. attention or mind' मनो नियुज् 7 A, 10, मनः समाधा or बंध् 9 P or आसंज् c. or निक्षिप्. 2 शास् 2 P, विनियम् 1 P, प्रणी 1 P, निवृत् c., अधिष्ठा 1 P, अवेक्ष् 1 A. 3 आ-निर्-उप-दिश्, प्रदृश् c. 4 नियुज्, आदिश्, आज्ञा c. (ज्ञापयति), प्रचुद् 10. 5 विधा 3 U, प्र-युज्. 6 (A letter &c.) *See* **Address. -a.** ऋजु, अवक्र, सरल, अकुटिल, अविलोम, अजिह्म, अनुलोम; 'd. descendants' अनुलोमाः, अनुलोमवंशजाः 2 क्रमागत, अविप्रकृष्ट. 3 व्यक्त, स्पष्ट, सुस्पष्ट-व्यक्त, प्रत्यक्ष, साक्षात् *ind.* **-ion,** *s.* शासनं, नियोगः, निर्देशः, आज्ञा, आदेशः. 2 संधानं, उद्देशः, प्रेरणं. 3 प्रणयनं, प्रशासनं, विनियमनं, अधिष्ठातृत्वं, अधिष्ठानं, अवेक्षा-क्षणं. 4 दिश् *f.*, दिशा, आशा, काष्ठा, ककुभ् *f.*, हरित् *f.* 5 Address q. v. **-ive,** *a.* निर्देशक, सूचक. **-ly,** *adv.* सपद्येव, सद्यः, अचिरात्, तत्क्षणं-णात्, अविलंबितं, शीघ्रं, आशु. 2 स्पष्टं, प्रत्यक्षं, सुव्यक्तं, अगूढतया, निर्व्याजं. 3 अनुलोमं, सरलतया. **-or,** *s.* शासितृ-अधिष्ठातृ *m.*, अनुशासकः, अध्यक्षः, अधिकारिन् *m.*, अवेक्षकः, निर्वाहकः. **-ory,** *s.* विधिसंहिता. 2 नामधामसूचकं पुस्तकं.

Direption, *s.* अपहरणं, अपहारः, लुंठनं.

Dirge, *s.* करुणगीतं, करुणरससंगीतं.

Dirigible, *a.* नियम्य.

Dirigle, *s. See* **Baloon.**

Dirk, *See* **Dagger.**

Dirt, *s.* मलः-लं, पंकः, कर्दमः, जंबालः-लं, कल्कं, किट्टं. **-y,** *a.* मलिन, समल, मलीमस, पंकिल, कलुष, आविल, मलदूषित, सकर्दम. 2 नीच, कुत्सित, खल, गर्ह्य. **-v. t.** मलेन-पंकेन-दुष् c. (दूषयति) or लिप् 6 P. मलिनीकृ 8 U, मलिनयति-आविलयति (D.).

Diruption, *See* **Eruption.**

Disable, *v. t.* अशक्त *a.* कृ 8 U, विहस्तीकृ, (रुजा विहस्तचरणां दूर्वा M. 4); अशक्त-असमर्थ *a.* कृ. 2 अशक्त c., विकलीकृ, उपहन् 2 P, दुर्बलीकृ. **-Disability,** *s.* अशक्ति *f.*, असामर्थ्यं, अक्षमता, अयोग्यता; अनुपयोगः.

Disabuse, *v. t.* भ्रमं निरस् 4 U or उच्छिद् 7 P or अपनी 1 P, or हृ 1 P or अपाकृ 8 U, भ्रांतिमुद् 6 P.

Disaccustom, *v. t.* अभ्यासं लुप् c.

Disadvantage, *s.* अहितं, अलाभः, अपकारः, अनर्थः, अनिष्टं, अपायः, हानि *f.*, पीडा, बाधा; 'at a d.' विषमावस्थ *a.*, असमवस्थ *a.* **-ous,** *a.* अहितकर (री *f.*), प्रतिकूल, अहित, अनुपकारक, विरोधिन्, अपायावह, क्षतिकारक. **-ously,** *adv.* अहितं, अनिष्टं, सापकारं.

Disaffect, *v. t.* विरंज् c., अपरागं उत्पद् c., उपजप् 1 P. **-ed,** *a.* वि अप-रक्त, विप्रिय, असंतुष्ट, अप्रीत, अननुरक्त. **-ion,** *s.* विरागः, असंतोषः, विरक्ति *f.*, अभक्ति *f.*

Disaffirmance, *s.* प्रत्याख्यानं, प्रत्यादेशः, प्रत्यावर्तनं.

Disagree, *v. i.* न संमन् 4 A, विवद् 1 A, भिद् pass., विरुध् pass., असदृशीभू; *See* **Differ. -able,** *a.* अनभिमत, अप्रिय, अनिष्ट, अहित, अप्रीतिकर (री *f.*), अरुचिर, अनाह्लादक. 2 विरुद्ध, प्रतिकूल. **-ment,** *s.* विसंवादः, विवादः, भेदः, विप्रतिपत्ति *f.*, विमति *f.*; *See* **Difference.**

Disallow, *v. t.* न अनुज्ञा 9 U, निषिध् 1 P, निंद् 1 P 2 प्रत्याख्या 2 P, प्रत्यादिश् 6 P, *See* **Deny, -ance,** *s.* प्रत्याख्यानं, निषेधः; निवारणं, निरसनं.

Disanimate, *See* **Discourage.**

Disannul, *See* **Abolish.**

Disappear, *v. i.* अंतर्-तिरः-धा pass., अंतर्-इ 2 P, तिरोभू 1 P, अदृश्य *a.* भू. 2 नश् 4 P, क्षयं-नाशं-या 2 P, प्र वि-ली 4 A, प्र-वि-ध्वंस् 1 A; 'the pigeons having d. ed' चक्षुर्विषयातिक्रांतेषु-नयनपथातीतेषु-अदृष्टिगोचरेषु-कपोतेषु. **-ance,** *s.* अंतर्धानं, तिरोधानं, अदर्शनं; नाशः, लयः, &c.; better ex. by (*v. i.*).

Disappoint, *v. i.* आशां भंज् 7 P or प्रति-वि-हन् 2 P or विफलीकृ or मोघीकृ 8 U or वंच् 10; विप्रलभ् 1 A; 'he was d. ed in his request' तस्य याच्ञा मोघी बभूव, स

भग्नाशो बभूव; ' d. ed in love ' खंडित-प्रणय, खंडित. -ed, *a*. भग्नाश, मोघाश, भग्नोद्यम, अकृतार्थ, प्रतिहत, मनोहत, प्रतिबद्ध. -ment, *s*. आशाभंगः, प्रणयवैफल्यं, विफलीकरणं, नैराश्यं, विप्रलंभः.

Disapprove, *v. t.* निंद् 1 P, गर्ह् 1, 10 A, न प्रशंस् 1 P; not approve q. v. **-Disapprobation,** *s*. निंदा, असंमति *f*., विरागः, अप्रीति *f*., विमति *f*., अनभिनंदनं.

Disarm, *v. t.* अस्त्राणि अपहृ 1 P or अपनी 1 P, निरायुधीकृ 8 U, निःशस्त्रीकृ. **2** (fig.) शम् c. (शमयति), सांत्व् 10. **-ed,** *a*. निरायुध, निःशस्त्र; ' d. of anger ' शांतरोष, क्षीणमन्यु.

Disarrange, *v. t.* क्रमं भंज् 7 P, व्यस् 4 U, संक 6 P, संकुलीकृ 8 U. **-ment,** *s*. अक्रमः, क्रमभंगः, व्यस्तता.

Disarray, *v. t.* अपनह् 4 P, उच्छद् 10, विवस्त्रीकृ 8 U. **2** क्रमं भंज् 7 P. **-s.** व्यूहभंगः, पिंजलः, समुत्पिंजः.

Disaster, *s*. आपद्-विपद् *f*., व्यसनं, उपप्लवः, विपत्ति *f*., उपद्रवः, अत्याहितं, अनर्थः. **-v. t.** पीड् 10, बाध् 1 A, उपहृ 1 A, उपद्रु 1 P. **-Disastrous,** *a*. विपद्युक्त, दुर्भाग्य, दुरंत; अनर्थावह, दारुण, घोर.

Disavow, -al, *See* **Deny, Denial.**

Disband, *v. t.* युद्धव्यापाराद् मुच् 6 P or c. सैन्यभंगं कृ 8 U. **2** मुच्, विमोक्ष् 10. **-v. i.** युद्धव्यापारान् मुच् 6 P.

Disbark, *v. t.* नौकायाः अवतॄ c.

Disbelieve, *v. t.* Not believe q. v. **-er,** *s*. नास्तिकः, अविश्वासिन् *m*. **-Disbelief,** *s*. अप्रत्ययः, अविश्वासः.

Disbend, *See* **Relax.**

Disbranch, *v. t.* निःशाखीकृ 8 U, शाखां लू 9 U.

Disburden, *v. t.* भारं अवतॄ c. or अपनी 1 P, निर्भार-रिक्तभार *-a.* कृ 8U; 'd one's mind ' मनोगतं अन्यस्मै आख्या 2 P ; ' the afflicted should d. their grief ' कर्तव्यानि दुःखितैर्दुःखनिर्वापणानि (U. 3).

Disburse, *v. t.* व्यय् 10 P (व्यययति), उत्सृज् 6 P, वि-नियुज् 7 A, 10, व्ययीकृ 8 U. **-ment,** *s*. व्ययः, उत्सर्गः, विनियोगः, त्यागः; ' receipt and d. ' आयव्ययौ.

Disc, *s*. *See* **Disk.**

Discard, *v. t.* अपास् 4 U, अवधू 5, 9 U, अपक्षिप् 6 P, निराकृ 8 U, अवसृज् 6 P, अपहा 3 P; निःसृ c., अपनुद् 6 P.

Discern, *v. t.* वि-विच् 3, 7 P, विचर् c., परिच्छिद् 7 P, निर्णी 1 P, परीक्ष् 1 A. **2** निर्वर्ण् 10, दृश् 1 P, ईक्ष् 1 A, आलोक् 1 A, 10. आलक्ष् 10, विभू c. **-er,** *s*. विवेचकः, ईक्षितृ *m*. **-ible,** *a*. दृश्य, दृष्टिगोचर, विभाव्य, प्रत्यक्ष. **-ing,** *a*. सूक्ष्मदर्शिन्, दीर्घ-दूर-दृष्टि, विवेकिन्, परिणामदर्शिन्, विचारशील. **-ingly,** *adv*. सविवेकं, सविचारं, सपरिच्छेदं. **-ment,** *s*. विवेकः, विवेचनं, परिच्छेदः, विचारः-रणा, परीक्षा, दूरदृष्टि *f*., अवबोधः, विज्ञान.

Discerption, *s*. व्यवच्छेदः, विभेदनं, विदारणं.

Discharge, *v. t.* (A load &c.) भारं अवतॄ c. or अपनी 1 P. **2** उद्-गॄ 6 P, उदीर् c., प्रमुच् 6 P, उच्चर् 10, उत्सृज् 6 P, प्रस्रु c., उद्वम् 1 P. **3** (Arrow &c.) मुच्, अस् 4 P, विसृज्, क्षिप् 6 P, प्रेर् c. निपत् c. ; ' d. a gun ' लोहनालीस्थं आग्नेयं चूर्णं ज्वल् c. **4** (अधिकारात् or पदात्) निःसृ c., अपकृष् 1 P, अवरुह् c. (रोपयति), निष्कस् c., निराकृ 8 U, अपास् 4 U, च्यु c., भ्रंश् c. **5** (Duty) कृ, अनुष्ठा 1 P, विधा 3 U, निष्पद्-संपद् c., निर्वह् c., आचर् 1 P. **6** (Debt) (ऋणं) शुध् c., निर्यत् 10, निराकृ, निस्तॄ c., विनी, आनृण्यं गम् 1 P. **7** मुच्, मोक्ष् 10, विसृज्. **8** (As a river) अवतॄ 1 P, द्रु 1 P; सागरं वर्जयित्वा कुत्र वा महानद्यवतरति (S. 3) ' will d. itself &c. ' **-v. i.** मुच् pass. ; स्रु 1 P. **-s.** भारावतरणं. **2** उद्गारः, प्रस्रावः, विसर्गः, उद्वमनं, उच्चारणं, उदीरणं. **3** क्षेपणं, मोक्षः. **4** अवरोपणं, अधिकारभ्रंशनं, पदच्युति *f*. भ्रंशः. **5** अनुष्ठानं, निर्वाहः, विधानं, संपादनं. **6** आनृण्यं, ऋणशोधनं-निस्तारः. **7** मोक्षः, मुक्ति *f*., मोचनं.

Disciple, *s*. शिष्यः, छात्रः, अंतेवासिन् *m*., विद्यार्थिन् *m*.

Discipline, *v. t.* विनी 1 P, शिक्ष् c., शास् 2 P, अधि-इ c. (अध्यापयति). **2** नियम् 1 P, विनियम्, शास्, दंड् 10, दम् c. (दमयति). **3** व्यायम् ; अभ्यस् 4 U. **-s.** विनयः, अनुशासनं, शिक्षा-क्षणं, अध्यापनं, अभ्यासः. **2** नियमः, व्यवस्था, विधिः, शासनं, नीति *f*. **3** दंडः, निग्रहः, दमनं, शिष्टि *f*., विनियमः-मनं; ' military d. ' युद्धाभ्यासः, युद्ध-रणशिक्षा; ' d. in arms ' शस्त्राभ्यासः.

Disclaim, -er, *See* **Deny, Denier.**

Disclose, *v. t.* विवृ 5 U, प्रकाश् c., व्यंज् 7 P, प्रकटीकृ 8 U, स्पष्टीकृ, भिद् 7 P or c., निविद् c., ख्या c, (ख्यापयति); ' d. ing secrets ' रहस्यभेदः. **-ure,** *s*. विवृति *f*., प्रकाशनं, निवेदनं, भेदः.

Discolour, *v. t.* वर्णांतरं ग्रह् c., कलुषी-मलिनीकृ 8 U, विवर्ण् 10, कृष्णीकृ. **-ation,** *s*. वैवर्ण्यं, कालुष्यं, मालिन्यं.

Discomfit, *v. t.* वि-प्र ध्वंस् c., व्यूहं भंज् or भिद् 7 P (as an army); पराजि 1 A, विद्रु c.: *See* **Defeat, Baffle. -ure,** *s*. भंगः, व्यसनं, पराजयः, पराभवः.

Discomfort, *v. t.* पीड् 10, व्यथ् c., बाध् 1 A; *See* **Afflict.** **-s.** अस्वास्थ्यं, दुःखं, पीडा, व्यथा, क्लेशः, बाधा.

Discommend, *See* **Censure.**

Discompose, *v. t.* क्षुभ् c., व्याकुलीकृ c., संभ्रम् c. (भ्रमयति), आकुलीकृ 8 U, बाध् 1 A. **-ed,** *a.* आकुलित, क्षुब्ध, व्याकुल, कातर, व्याकुलचित्त, अनवस्थित, व्यग्र, भ्रांत, पारिप्लव, विक्लवचित्त. **-ure,** *s.* क्षोभः, आकुलत्वं, व्यग्रता, वैक्लव्यं, उद्वेगः, अस्वास्थ्यं, अस्थिरता.

Disconcert, *v. t.* खंड् 10, मोघीकृ 8 U, प्रति-व्या-हन् 2 P; *See* **Baffle.** **2** **Discompose,** q. v.

Disconformity, *s.* विरोधः, विरुद्धता, असादृश्यं, असंगति *f.*, विसंवादः, विप्रतिपत्ति *f.*

Disconnect, *See* **Separate.** **-ion,** *s.* विश्लेषः, असंगति *f.*, वियोगः.

Disconsolate, *a.* खिन्न, विषण्ण, दीन, उद्विग्न, म्लान; *See* **Dejected.** **-ly,** *adv.* सविषादं, सखेदं, सोद्वेगं.

Discontent, *a.* असंतुष्ट, अतृप्त. **-s.** असंतोषः, अतृप्ति *f.*, अप-वि-रागः, विरक्ति *f.*, अप्रीति *f.* **-v. t.** असंतोषं उत्पद् c. or जन् c.

Discontinue, *v. t.* त्यज् 1 P, विच्छिद् 7 P, विरम् c. (रमयति), निवृत् c., उज्झ् 6 P, विलुप् c. **-v. i.** वि-उप-रम् 1 P, निवृत् 1 A, (with abl.); *See* **Cease.** **-ance,** **-ation,** *s.* विच्छेदः, विरामः, निवृत्ति *f.*; उपशमः, भंगः, अंतरायः.

Discord, *v. i.* विसंवद् 1 P, विभिद्-न युज्-विरुध् pass. **-s.,** **-ance,** *s.* भेदः; भिन्नता, विसंवादः, मतभेदः, विरोधः, विनति *f.*, वैमत्यं, वैपरीत्यं, वैलक्षण्यं; 'd. of sound' स्वरविरोधः, अपस्वरः. **-ant,** *a.* विषम, प्रतिकूल, विरुद्ध, विसंवादिन्, परस्परविरुद्ध, विभिन्न, असंगत, विपरीत; 'd. sound' विस्वरः, अपस्वरः, कर्कशध्वनिः.

Discount, *v. t.* भागं उद् हृ 1 P. **-s.** उद्धारः, उद्धृतभागः.

Discountenance, *v. t.* न अनुग्रह् 9 P, न उपकृ 8 U, न अनुमुद् 1 A.

Discourage, *v. t.* उत्साहभंगं कृ 8U, अव-विसद् c., विषादं जन् c., विषण्णीकृ, धैर्यं ध्वंस् c., मनः or आशाः भंज् 7 P. **2** **Deter,** q.v. **-ed,** *a.* भग्नोत्साह, हताश, भग्नाश्रम, विषण्ण, अवसन्न, खिन्न, निरुत्साह, मनोहत, प्रतिबद्ध, भग्नाश, धैर्यच्युत, स्खलितधैर्य. **-ing,** *a.* विषादजनक, धैर्यध्वंसिन्. **-ment,** *s.* धैर्यध्वंसः, उत्साहभंगः, आशा-उद्यम-भंगः; विषादः, अवसादः, खिन्नता, धैर्य-च्युति *f.* स्खलनं.

Discourse, *v. i.* संवद् 1 P, संभाष् 1 A, समालप् 1 P. **2** भाष् 1 A, वद्-गद् 1 P, अधिकृत्य वच् 2 P. **-s.** संवादः, संभाषणं, संकथा, संलापः. **2** वचनं, भाषणं, उक्ति *f.*, वचस् *n.*; *See* **Converse.** **-ation.** **-er,** *s.* वादिन् *m.* वक्तृ *m.* **-ive,** *a.* तार्किक (की *f.*), ऊहिन्, तर्कविषय.

Discourteous, *a.* असभ्य, अशिष्ट, अविनीत, दुःशील, अनार्य. **--ness,-Discourtesy,** *s.* अविनयः, अनार्यता, असभ्यता, मर्यादातिक्रमः, अशिष्टाचारः.

Discover, *v. t.* विद् 5 U, दृश् c., प्रकाश् c., आविष्कृ 8 U, स्पष्टीकृ, व्यक्तीकृ, प्रकटीकृ, व्यंज् 7 P, ज्ञा c. (ज्ञापयति), आनि-विद् c. **2** निरूप् 10, ज्ञा 9 U, उपलभ् 1 A, निर्णी 1 P. **3** समा-आ-सद् c., प्राप् 5 P, विद् 6 U, दृश् 1 P, अधिगम् 1 P, इ-या 2 P. **-er,** *s.* निर्णेतृ-अधिगंतृ *m.*, निरूपकः. **-y,** *s.* प्रकाशनं, विवरणं. **2** ज्ञानं, अवगमः, दर्शनं, निर्णयः, उपलब्धि *f.*, समासादनं, निरूपणं, प्राप्ति *f.*

Discredit, *v. t.* न विश्वस् 2 P. न प्रति-इ 2 P, अविश्वास्य *a.* मन् 4 A, प्रामाण्यं लघयति (D.). **2** कलंकयति (D.), अकीर्तिं आवह् 1 P, दुष् c. (दूषयति), मलिनीकृ 8 U, मलिनयति (D.). **-s.** अपयशस् *n.*, अपकीर्ति *f.*, दूषणं, कलंकः, अप्रतिष्ठा, अकीर्ति *f.*; 'bring d. on' दुष् c. मलिनयति; (यदा मेधाविनी शिष्योपदेशं मलिनयति M. 1). **-able,** *a.* अकीर्तिकर-अयशस्कर (री *f.*), गर्हित, कलंककर, दूषणीय, गर्ह्य, निंद्य.

Discreet, *a.* समीक्ष्य विमृश्य-कारिन्, विचक्षण, स्ववहित, विचारशील, सावधान, दीर्घ-दूर-दृष्टि. **2** (Of acts.) साधु, श्रेयस्. **-ly,** *adv.* विमृश्य, समीक्ष्य, विचार्य. **-Discretion,** *s.* विवेकः, विमृश्यकारित्वं, समीक्षणं, विचक्षणता, विचारः, विज्ञता. **2** स्वातंत्र्यं, स्वाधीनता, 'having reached the years of d.' प्राप्तव्यवहारदशः. **3** विकल्पः, कामः, रुचि *f.*, छंदः; 'at d.' विना समयेन; 'this matter is left to your d.' यथा भवानुचितं मन्यते तथा क्रियतां; स्वरुच्या-कामतः-वर्ततां भवान्; 'at one's own d.' स्वच्छंदं, स्वेच्छया, स्वरुच्या, कामतः. **-ally,** *adv.* स्वेच्छानुसारेण, यथाकामं. **-ary,** *a.* स्वाधीन, वैकल्पिक-याहृच्छिक (की *f.*), स्वेच्छानुवर्तिन्.

Discrepant, *a.* विभिन्न, विरुद्ध, विपरीत, अवि-संगत, विसंवादिन्, विरोधिन्, प्रतिकूल. **-Discrepance, -cy,** *s.* विभेदः, विरोधः, विप्रतिपत्ति *f.*, असंगति *f.*, विसंवादः, वैलक्षण्यं, वैपरीत्यं.

Discrete, *a.* विभिन्न, विविक्त. **2** अवधारणार्थक.

Discriminate, *v. t.* वि-विच् 3, 7 P, विशिष् 7 P or c., परिच्छिद् 7 P. विज्ञा 9 U, विभज् 3 U, विचर् c. **2** लक्ष् 10, परीक्ष् 1 A, सं-अव-ईक्ष्. **-ion,** *s.*

विवेकः, परिच्छेदः, विज्ञानं, विचारणं-णा; विशेषः, अवधारणा : 'd. of proper and improper' पात्रापात्रविचारणा ; 'd. of right and wrong' सदसद्विवेकः. -ing, -ive, a. विशेषज्ञ, गुणदोषविद्, विवेकिन्, परिच्छेदक.

Discursive, a. नानाविषय, अनेकप्रसंग; अस्थिर,चंचल, अनवस्थित. 2 तार्किक (की f.), ऊहिन्.

Discus, s. चक्रं.

Discuss, v. t. विचर् c., पर्यालोच् 10. वितर्क् 1, विमृश् 6 P, परीक्ष् 1 A, निरूप् 10, अनुसंधा 3 U, 'd. in detail at length, exhaustively' प्रपंचयति (D.) प्रपंचं कृ 8 U, सविस्तरं-विस्तरेण-वर्ण् 10. -v. i. विवद् 1 A, वादे व्यापृ 6 A. -ion, s. विचारः-रणा, वितर्कः, परीक्षा, निरूपणं, विमर्शः, वादविवादः, पर्यालोचनं ; 'to turn to the subject under d.' प्रकृत-प्रस्तुतं-अनुसृ 1 P or अनुवृत् 1 A or अनुसंधा; 'subject under d.' प्रस्तावः, प्रस्तुत-प्रकृत-विषयः, प्रस्तुतं, प्रकृतं; 'result of d.' सचिंतार्थः.

Discussive, Discutient, a. शोथघ्न (घ्नी f.), शोथहृत्, दुष्टधातुनाशक.

Disdain, v. t. अवमन् 4 A, अवज्ञा 9 U, अवगण् 10, तिरस्कृ 8 U; *See* **Contemn.** -s. औद्धत्यं, सावज्ञावलेपः, अवमानः नना, अवहेलना; *See* **Contempt.** -ful, a. सावज्ञ, सावलेप, अवमानिन्; उद्धत, अवलिप्त, सावमान.

Disease, s. रोगः, गदः, व्याधि m., आमयः, उपतापः, रुजा, रुज् f., विकारः, पीडा, क्लेशः, अस्वास्थ्यं.-v. t. रोगेण व्यथ् c. or पीड् 10 or क्लिश् 9 P. -ed, a. व्याधिग्रस्त. रोगोपसृष्ट, रोगार्त, सरोग, सरुज, सामय, आतुर, विकृत, अस्वस्थ.

Disembark, v. i. पोतात्-नौकायाः अवतॄ 1 P, or अव-रुह् 1 P. -v. t. अवतॄ-रुह् c. -ation, s. अवरोहणं, उत्तरणं.

Disedge, *See* **Blunt.**

Disembarrass, *See* **Clear.**

Disembitter, v. t. तिक्तत्वं-कटुत्वं-अपनी 1 P, मधुरीकृ 8 U, सुरस a. कृ.

Disembody, v. t. *See* **Disband.** 2 देहबंधान्मुच् c. -ed, a. अशरीर, देहहीन, कायहीन, and sim. comps.

Disembogue, v. i. निर्गम्-निस् 1 P, समुद्रं अवतॄ 1 P or प्रविश् 6 P or प्रस्रु-स्रु 1 P (of a river.). -v. t. सलिलं सागरे निर्गम् c., &c.

Disemploy, *See* **Discharge.**

Disenable, *See* **Disable.**

Disembroil, v. t. उद्वेगात्-संभ्रमात्-मुच् c. or उद्धृ 1 P.

Disenchant, v. t. प्रतिकृ 8 U, मंत्रवशात् उद्धृ 1 P.

Disencumber, v. t. प्रतिबंधान् अपनी 1 P or अपसृज् 6 P; निर्विघ्नीकृ 8 U, निरुपद्रव a. कृ.

Disengage, v. t वियुज् 7 A, 10. विश्लिष् c. 2 मुच् c. P or c., मोक्ष् 10, उद्-धृ 1 P; 'd. the mind' मनो निवृत् c. -v. i. मुच् pass., निवृत् 1 A, विश्रम् 4 P. आत्मानं निवृत् c. -ed, a. मुक्त, उद्धृत, उत्तीर्ण. 2 लब्धक्षण, प्राप्तावकाश, प्राप्तावसर, अव्यापृत, कार्यरहित-शून्य, कार्यविरत, निर्व्यापार. -ment, s. मोक्षणं, &c 2 अवसरः, क्षणः; अवकाशः.

Disentangle, v t. **Disengage,** q. v. 2 वियुज् 7 A, 10, विश्लिष् c.

Disenthral, v. t. दास्यात् मुच् 6 P, or c. or मोक्ष् 10.

Disentrance, s मूर्च्छनात् प्रबुध् c.

Disesteem, v. t. अवमन् 4 A, अवज्ञा 9 U; *See* **Contemn.** -s. अनादरः, अवमानः, अवज्ञा, उपेक्षा.

Disfavour, v. t. न अनुग्रह् 9 P, न उपकृ 8U, न अनुरुध् 4 A. -s. अकृपा, अननुग्रहः, अप्रसादः, अनुपकारः, पराङ्मुखता, विरक्ति f., अप-वि-रागः, अप्रीति f., असंतोषः.

Disfigure, v. t. विरूप् 10, विरूपीकृ 8 U, विकृ 8 U, व्यंगयति (D.), विकलीकृ, विप्रकृ c., (रूपं प्रसाधनैर्विप्रकार्यते S. 4). -ed, a. वि-कु-अप-रूप, विकृताकार, विकृत, व्यंग (गी f.). -ment, s. विरूपता, वैकल्यं, व्यंगता, विप्रकारः.

Disfranchise, v. t. पारत्वं-पौराधिकारं-हृ 1 P or विलुप् c.

Disgorge, v. t. उद्-गॄ 6 P, उद्वम् 1 P, विच्छर्द् 10. -ment, s. उद्गारः, उद्वमनं, वमथुः, प्रच्छर्दिका.

Disgrace, s. अपमानः, अव-वि-मानना, परि-अभि-भवः, निकृति f., अ-अप-कीर्ति f., अ-अप यशस् n., कलंकः, दूषणं. 2 कलंकास्पदं. अवमानहेतुः 'a d. to the family' कुलांगारः, कुलपांसुलः. -v. t. अप-अव-मन् c., कलंकयति (D.), अकीर्ति-अयशः-कृ; परि-अभि-भू 1 P. दुष् c. (दूषयति); गर्ह् 1, 10 A, सावज्ञं निर्भर्त्स् 10 A. 2 **Degrade,** q. v. -ful, a. अयशस्कर (री f.,), कलंककर (री f.); गर्हित, अपमानहेतुक; लज्जाकर (री f.), अवमानजनक; निंद्य, दूषणीय. -fully, adv. गर्हितं; लज्जाकरं, सापमानं. -ious, a. अप्रसन्न, अननुकूल.

Disguise, v. t. कपटवेशेन-वेशांतरेण-छद् 1 U or आच्छद् 10, 'd. ed as' वेष-रूप-धारिन् in comp.; 'd. ed as ascetics' तपस्विव्यंजनोपेताः,तापसच्छद्मना,तापसरूपधारिणः, &c. 2 (Oneself) वेषांतरं-वेषपरिवर्तनं कृ 8U

or विधा 3 U, अन्यवेषं परिधा 3 U, वेषं प-रिवृत् c.; 'd. ing himself differently' वेषांतरं विधाय, परिहितान्यवेषः; 'd. ed himself with a lion's skin सिंहचर्मपरिच्छन्नः बभूव. 2 अप-नि-ह्नु 2 A, गुप् 1 P, 10, गुह्, *See* **Conceal.** **–s.** कपट-छद्म-वेषः, वेषांतरं, आकारगोपनं; विडंबनं, अभिनयः. 2 छद्मन् *n.*, छलं, व्याजः, अप-व्यप-देशः, लक्षं. **–ed,** *a.* कपट-छद्म-वेषिन्, कपटवेष, कपटरूप; रूपवेष, &c., in comp.; 'd. praise' व्याजस्तुति *f.*

Disgust, *v. t.* उद्वेग-निर्वेद-उत्पद् c., अरुचिमुत्पद् c., उद्विज् c.; निर्विद् c. **–s.** जुगुप्सा, उद्वेगः, घृणा, निर्वेदः; अरुचि *f.*, विरक्ति *f.*, बीभत्सं; 'in d.' सनिर्वेदं. **–ing, –ful,** *a.* बीभत्स, अरुचिर, कुत्सित, गर्ह्य, उद्वेगकर (री *f.*), जुगुप्सावह; 'to be d. ed with' उद्विज् 6 A (with abl.); निर्विद् pass., निर्विण्ण *a.* भू (with instr.), बध् desid. (बीभत्सते) (with abl.).

Dish, *s.* शरावः, पात्रं, भाजनं. 2 भोजनं; आहारविशेषः.

Dishabille, *a.* विवस्त्र, कुचेल, अकृताभरण. **–s.** लघुवासस् *n.*

Dishearten, *See* **Discourage.**

Dishevel, *v. t.* प्र-वि-कॄ 6 P, ध्वंस् 1 A. **–ed,** *a.* प्र-वि-कीर्ण, पर्याकुल, स्रस्त; 'having d. hair' मुक्त-स्रस्त-केश.

Dishonest, *a.* अशुचि, असरल, अनृजु, सव्याज, जिह्म, कुटिल, कापटिक (की *f.*), छाद्मिक (की *f.*), शठ, धूर्त, सव्यलीक; 'a d. woman' असती, भ्रष्टा, व्यभिचारिणी. **–ly,** *adv.* अन्यायेन, कपटेन, कुटिलं, धूर्ततया, सव्याजं, छलेन. **–y,** *s.* अशुचित्वं, कापट्यं, कौटिल्यं, माया, &c.

Dishonour, *v. t.* **Disgrace,** q. v. 2 अवमन् 4 A, अवज्ञा 9 U, अवधीर् 10, अनादृ 6 A; *See* **Contemn;** 'd. a maiden' दुष् c. (दूषयति), सतीत्वात् भ्रंश् c. **–s.** अपमानः, अनादरः, अयशस् *n.*, अकीर्ति *f.*, कलंकः, अप्रतिष्ठा. **–able,** *a.* अनार्य, कलंककर (री *f.*), *See* **Disgraceful.**

Dishumour, *s.* स्वभाववक्रता, वक्रशीलता, प्रकृतिकर्कशत्वं, प्रतीपता.

Disillusion, *v. t.* मोहं or भ्रमं निरस् 4 P.

Disincline, *v. t.* विरञ्ज् c., विरागं जन् c.; or उत्पद् c. **–ation,** *s.* अस्पृहा, निरीहत्वं, विरागः, विरक्ति *f.*, द्वेषः, अनीहा, विमुखता, अनिच्छा, अरुचि *f.*, अप्रीति *f.* **–ed,** *a.* विरक्त, वि-पराङ्-मुख (खी *f.*), अनिच्छु, निरीह, निःस्पृह.

Disinfect, *v. t.* शुध् 4 P, निर्दोषं कृ 8 U **–ant,** *a*, विषघ्न.

Disingenuous, *a.* अनुदार, अकुटिल, असरल; *See* **Dishonest.**

Disinherit, Disherit, *v. t.* रिक्थाधिकारात् भ्रंश् c., पैतृकं धनं लुप् c. **–ed,** *a.* अनधिकार, पैतृकधनहीन. **–ing,** *s.* पैतृकरिक्थच्छेदः-लोपः.

Disintegrate, *v. t.* वियुज् 10, संहतिं भिद् 7 P, विश्लिष् c.; *See* **Separate.** **–ion,** *s.* वियोगः, विश्लेषः, संहतिभेदः.

Disinter, *v. t.* (शव) उत्खन् 1 P.

Disinterested, *a.* निःस्पृह, उदासीन, निर्मम, निष्काम, मुक्तसंग, निःसंग, अपक्षपातिन्, निरीह, आत्महितानिरपेक्ष, निष्कारण; 'a d. friend' निष्कारणो बंधुः. **–ly,** *adv.* निर्ममं, स्वार्थनिरपेक्षं, निःस्पृहं. **–ness,** *s.* निरीहता, निःसंगता.

Disjoin, Disjoint, *v. See* **Separate.** 2 (Disjoint) विसंधा 3 U, संधिं भञ्ज् 7 P, or त्रुट् c. 3 व्यवच्छिद् 7 P, अवकृत् 6 P. **–ed,** *a.* असंश्लिष्ट, असंहत, असंयत, असंबद्ध, अनन्वित, असंलग्न.

Disjunct, *a.* वियुक्त, विश्लिष्ट, असंलग्न, विभिन्न. **–ion,** *s.* वियोगः; विश्लेषः, विभेदः, असंगतता, असंधानं. **–ive,** *a.* वियोगिन्.

Disk. *s.* बिंबं, मंडलं, परिवेषः, परिधिः. 2 चक्रं.

Dislike, *s.* अरुचि *f.*, विरागः, विरक्ति *f.*, विमुखता, द्वेषः; *See* **Disinclination.** **–v. t.** द्विष् 2 U, विरञ्ज् pass. (with loc.), न रुच् 1 A, न अभिनंद् 1 P, न इष् 6 P. **–ed,** *a.* अप्रिय, अनिष्ट, विद्विष्ट, अनीप्सित.

Disliken, *v. t.* असमीकृ 8 U, अतुल्यीकृ.

Dislocate, *v. t.* संधेः चल् c. or च्यु c., संधिं त्रुट् c. or भञ्ज् 7 P, विसंधा 3 U. **–ion,** *s.* संधित्रोटनं, संधिभंगः, विसंधानं, संधिच्युति *f.*

Dislodge, *v. t.* अप-निः-सृ c., निरस् 4 P, निष्कस् c.; *See* **Drive.** 2 वि-प्र-वस् c., निर्वस् c., गृहाद्बहिष्कृ 8 U. **–v. i.** अपसृ 1 P, स्थानांतरं गम् 1 P, स्थानांतरे निविश् 6 P.

Disloyal, *a.* भक्तिहीन, राजद्रोहिन्, राजापकारकारिन्, अराजनिष्ठ, अप-वि-रक्त, असंतुष्ट. **–ly,** *adv.* भक्तिहीनतया, राजद्रोहेण, अपरागेण. **–ty,** *s.* राजद्रोहः, अभक्ति *f.*, अप-वि-रागः, राजापकारकारिता, असंतोषः.

Dismal, *a.* उदासीन, अप्रसन्न, सशोक, सखेद, निरानंद, निरुल्लास. 2 उग्र, दारुण, घोर, रौद्र (द्री *f.*), भैरव (वी *f.*), भयमय, भयानक. **–ly,** *adv.* उग्रं, भयानकं. **–ness,** *s.* दारुणता, उग्रता; औदासीन्यं.

Dismantle, *v. t.* वर्म अपहृ 1 P, विवस्त्रीकृ 8 U. 2 उपकरणादिकं हृ, उपस्करादि अपनी 1 P.

Dismask, *v. t.* कपटवेषं अपवृ c.

Dismast, *v. t.* कूपकं भञ्ज् 7 P.

Dismay, *s.* सं-,त्रासः, साध्वसं, भयं, भीति *f.*, उद्वेगः, सविस्मयः त्रासः, आकुलत्वं, कातर्यं; 'filled with d.' [illegible]

—*v. t.* संत्रस् c., विस्मयं-साध्वसं उत्पद् c., भयेन उपहन् 2 P, उद्विज् c., *See* **Daunt.**

Dismember, *v. t.* अंगानि विपद् c.(पदयति) or पृथक् कृ 8 U, अवयवशः छिद् 7 P; विभज् 1 U, विश्लिष् c., वियुज् 7 A, 10. **—ment,** *s.* अंगव्यवच्छेदः, अवयवशः विभागः, विश्लेषः; भंगः.

Dismiss, *v. t.* विसृज् 6 P or c., प्रस्था c. (स्थापयति), संप्रेष् c., गंतुं अनुज्ञा 9 U or आदिश् 6 P. 2 (From office &c.) अधिकारात्-पदात् च्यु c. or भ्रंश् c. or अवरुह् c., *See* **Discharge;** 'd. ed from office' अधिकारच्युत-भ्रष्ट, भ्रष्टाधिकार. 3 अपास् 4 P, हा 3 P, उत्सृज्, अपनी 1 P, अपनुद् 6 P, त्यज् 1 P, दूरीकृ 8 U, निरा-अपा-कृ, मुच् 6 P; 'd. all anxiety' सर्वथा वीतचिंतो भव, औत्सुक्यमपाकुरु. 4 प्रत्याख्या 2 P, प्रत्यादिश् 6 P. **—ion, —al,** *s.* प्रस्थापनं, विसर्जनं. 2 पदात् अवरोपणं; अधिकारभ्रंशः-च्युति *f.*, पदहानि *f.* 3 निराकरणं; प्रत्यादेशः, त्यागः, &c.

Dismount, *v. i.* (अश्वात्-अश्वपृष्ठात्) अवतृ-अवरुह् 1 P. —*v. t.* Causal of roots above.

Disobey, *v. t.* (Orders) भंज् 7 P, उल्लंघ् 1 A, 10, अतिक्रम् 1 U, 4 P, अतिचर् 1 P; प्रतीपं गम् 1 P, न अनुष्ठा 1 P, न अनुवृत् 1 A, न अनुरुध् 4 A; (persons) आज्ञां भंज्, &c.; 'he was never d. ed' तस्याज्ञा कदापि नोल्लंघिता, &c. **—Disobedience,** *s.* आज्ञाभंगः, आज्ञालंघनं, शासनव्यतिक्रमः, अननुष्ठानं, प्रतीपाचरणं, अननुरोधः. **—Disobedient,** *a.* प्रतीपाचार, निदेशलंघिन्, अविधायिन्, अननुवर्तिन्, अवश, प्रतीप, not 'obedient' q. v.

Disoblige, *v. t.* अप्रियं आचर् 1 P, अपराध् 4, 5 P (with gen. or loc.), असंतोषं उत्पद् c., प्रतिकूलं-विप्रियं आचर् or अनुष्ठा 1 P. **—ation,** अप्रियं, अपराधः, विप्रियं. **—ing,** *a.* अननुरोधिन्, अननुकूल, असंतोषकर (री *f.*).

Disorder, *s.* आकुलत्वं, तुमुलं, विप्लवः, वैक्लव्यं, संभ्रमः, पर्याकुलता. 2 अक्रमः, क्रमभंगः, अव्यवस्था, व्यस्तता, संकरः, संक्षोभः, व्यतिक्रमः. 3 रोगः, पीडा, व्याधिः, आमयः, अस्वास्थ्यं; 'd. of the stomach' जठरामयः, अन्नविकारः; 'd. in the army' समुत्पिंजः, पिंजलः, अत्यंतमाकुलं. —*v. t.* आकुलीकृ 8 U, व्यस् 4 U, व्यामुह् c., संभ्रम् c. (भ्रमयति). 2 पर्यस्, संक्षुभ् c., क्रमं भंज् 7 P, संकरीकृ 8 U, संकुलीकृ. 3 पीड् 10, व्यथ् c., अस्वस्थ *a.* कृ. **—ed,** *a.* विपर्यस्त, भग्नक्रम, व्यस्त, व्यत्यस्त, संकुल, संकीर्ण, अव्यवस्थित; 'd. in mind' आकुल, संभ्रांत, व्यग्र-मूढ-चित्त. 2 अस्वस्थ, पीडित, आतुर, व्याधुपहत, रुग्ण, रुजार्त. **—ly,** *a.* अव्यवस्थित, *See* above. 2 अनवस्थित, नियमविरुद्ध, अवश, अनियत, उद्दाम, उच्छृंखल, अविधेय. —*adv.* अक्रमं, क्रमभंगेन; ससंभ्रमं. 2 अविधितः, विधि-नियम-विरुद्धं.

Disorganize, *See* **Disorder.**

Disown, *v. t.* प्रत्याख्या 2 P, प्रत्याचक्ष् 2 A; *See* **Deny.**

Disparage, *v. t.* परिभू 1 P, उपेक्ष् 1 A, अपकृष् 1 P, अवज्ञा 9 U; *See* **Contemn.** 2 मूल्यं न्यूनीकृ 8 U, अवमन् 4 A, लघूकृ, अपलप् 1 P; *See* **Depreciate.** 3 अयोग्यविवाहे संबंध् 9 P. अयोग्यसंयोगेन अपकृष्. **—ment,** *s.* अवज्ञा, तिरस्कारः, अवमाननं परिभवः, उपेक्षा; अभ्यसूया, परीवादः, गुणापकर्षः, गुणापलापः. 2 अयोग्यसंबंधः. **—er,** *s.* निंदकः, अवमानिन् *m.*

Disparity, *s.* असाम्यं, विषमता, वैषम्यं, भेदः, असमानता, असंगतता, असंगति *f.*

Dispart, *v. t.* विभज् 1 U, द्विधा भिद् 7 P, वियुज् 7 A, 10.

Dispassion, *s.* विरागः, प्रशांति *f.*, अक्रोधः; निरीहता, औदासिन्यं, निःसंगता. **—ate,** *a.* वीतराग, शांत, असंभ्रांत, उदासीन, अक्रोधन, निरीह, निःसंग, विरक्त, मुक्तसंग, समचित्त, अपक्षपातिन्. **—ately,** *adv.* शांतचेतसा, समबुद्ध्या, असंभ्रमं, अपक्षपातेन.

Dispatch, *See* **Despatch.**

Dispel, *v. t.* अप-परा-नुद् 6 P, निर्-अप-अस् 4 U, निराकृ 8 U, प्रति-अप-निः-सृ c., अपनी 1P, अप-ऊह् 1 U, अपाकृ, उच्छिद् 7 P, हृ 1 P, नश् c., विभिद् 7 P, वि-प्र-ध्वंस् c., अव-उत्-सद् c., हन् 2 P, (gen. in comps).

Dispensary, *s.* औषधशाला, रोगचिकित्सास्थानं.

Dispense, *v. t.* विधा 3 U, प्रणी 1 P, निर्वह् c., प्रवृत् c.; 'd. er of laws' राजशासनानां प्रवर्तयिता. 2 विभज् 1 U, पृथक् पृथक् विन्यस् 4 U, or विधा or वितृ 1 P, परिक्लृप् c. 3 (with) Ex. by न कार्यं or न प्रयोजनं; 'I d. with your services' तव सेवया न मे किमपि कार्यं-प्रयोजनं; उपेक्ष् 1A, त्यज् 1 P, अवसृज् 6 P. **—ation,** *s.* विभजनं, विभागः, प्रणयनं, वितरणं, भागकल्पनं, परिकल्पनं. 2 व्यवस्थाभंगानुज्ञा, नियमलंघनानुमति *f.* 3 ईश्वरस्य नरेण संव्यवहारः. **—ator,** *s.* विभजकः, विभागकल्पकः. **—er,** *s.* प्रवर्तकः, प्रणेता, निर्वाहकः.

Dispeople, *v. t.* निर्जनीकृ 8 U.

Disperse, *v. t.* अप-वि-कृ 6 P, विक्षिप् 6 P, इतस्ततः विद्रु c. or गम् c.; वि-प्र-सृ c., पर्यस् 4 U, दिशि दिशि गम् c.; *See* **Dispel.** —*v. i.* अप-सृ 1 U or विद्रु 1 P; *See* **Break up. —er,** *s.* विद्रावयितृ *m.*, उच्छेदकः; अपहः, नाशकः, हरः, in comp. **—ion.**

s. विद्रावणं, विक्षेपः, विकिरणं.

Disspirit, *See* **Discourage.**

Displace, *v. t.* (स्वस्थानात्) विचल् c., अप-निः-सृ c., निरस् 4 U, भ्रंश् c., च्यु c., निराकृ 8 U, अपास्. **2 Discharge,** q. v. **-ment,** *s.* स्थाननाशः-भ्रंशः, स्वस्थानात्-चलनं-च्युति *f.*

Displant, *v. t.* उन्मूल् 10, उच्छिद् 7 P, उत्पट् 10. **2** निर्वस् c., स्थानात् भ्रंश् c. or निरस् 4 U.

Display, *v. t.* दृश् c., प्रकाश् c., व्यंज् 7 P, विवृ 5 U, आविष्कृ 8 U, प्रकटीकृ, स्फुटीकृ. **2** वितन् 8 U, विस्तृ c., प्रसृ c., विकस् c., विलस् c.; 'd. itself उद्-वि-जृंभ् 1 A. **-s.** उल्लासः, विकासः, प्रकाशनं, दर्शनं, व्यक्ति *f.*, विवरणं, आविष्करणं, विजृंभणं, विजृंभितं, विलासः, विलसितं; 'd. of genius' मतिविलासः ; 'd. of ignorance' अज्ञानविजृंभित.

Displease, *v. t.* विप्रियं-अभिष्टं-कृ 8 U, असंतोषं-कोपं-जन् c., प्रतिकूलं आचर् 1 P, कुप् c., रुष् c., अपराध् 4, 5 P (with gen. or loc.), वि-अप-रंज् c. **-ed,** *a.* असंतुष्ट, जातामर्ष, कृतरोष, अप्रसन्न, रुष्ट, कुपित, अप-वि-रक्त. **-ing,** *a.* अप्रिय, असंतोषजनक, कोपावह. **-ure,** *s.* असंतोषः, क्रोधः, अप्रसादः, अप-वि-रागः *See* **Anger.**

Displode, *See* **Explode.**

Displume, *v. t.* पक्षान् उद्-हृ 1 P or उत्पट् 10.

Disport, *v. See* **Amuse, Play.** **-s.** विहारः, क्रीडा, केलि *f.*, विलासः.

Dispose, *v. t.* विन्यस् 4 U, रच् 10, संविधा 3 U, विनियुज् 7 A, 10, व्यूह् 1 U, क्रमेण स्था c. (स्थापयति). **2** विनि-प्र-युज्, निक्षिप् 6 P, दा 3 P, वितॄ 1 P. **3** प्र-उप-क्लृप् c. **4** प्रवृत् c., प्रयुज् 10, प्रोत्सह् c. **-of,** विनि-उप-प्र-युज् ; 'how have you d. ed of my money' मम द्रव्यस्य कथं त्वया विनियोगः कृतः ; 'd. of goods' विक्री 9 A; 'd. of time' क्षै c. (क्षपयति), नी 1 P, या c. ; 'd of a girl' (विवाहे) दा, वितॄ, प्रतिपद् c. **2** (Perform) समाप् c., अवसो 4 P. **-al,** *s.* विन्यासः, रचना, व्यवस्थापनं, परिपाटि-टी *f.* **2** विनियमः. **3** समर्पणं, वितरणं, विनियोगः, परिकल्पनं, प्रविभागः. **4** अधिकारः, वशः-शं, अधीनता, आयत्तता ; 'I am at your d.' अहं त्वदधीनोस्मि ; 'this matter is at your d.' अयमर्थस्त्वदायत्तः, अत्र भवान् प्रभवति ; 'divine d.' परमेश्वरेच्छा, नियतिः. **-ed,** *a.* विन्यस्त, व्यवस्थित, रचित. **2** (Inclined) ex. by शील in comp., or काम with inf. ; 'd. to quarrel' कलहशील, कलहकाम ; 'd. to fall' पातुक, पतयालु ; 'd. to go' गंतुकाम ; 'well-d.' सुस्वभाव, स्निग्ध, सस्नेह. **-er,** *s.* प्रदातृ *m.*, विनियोगकृत् *m.* **2** विनियंतृ *m.*; अधिष्ठातृ *m.*, शासितृ *m.* **-ition,** *s.* **Disposal,** q. v. **2** भावः, स्वभावः, शीलः-लं, प्रकृति *f* ; 'good d.' सद्भावः, साधुशीलत्वं, सौजन्यं, सुशीलं. **3** प्रवृत्ति *f.*, प्रवणता, शीलता-आलुता in comp. **-ure,** *s.* अधिकारः, शक्ति *f.*, विनियोगसामर्थ्यं. **2** अवस्थानं.

Dispossess, *v. t.* अधिकारात्-स्वत्वात्-भ्रंश् c. or निराकृ 8 U, स्वत्वं हृ 1 P; 'd. ed of one's right' हृताधिकार, अधिकारभ्रष्ट.

Dispraise, *See* **Censure.**

Dispread, *v. t.* नानादिक्षु विसृ c., बहुधा वि-क्षिप् 6 P.

Disproportion, *s.* वैषम्यं, असमता, अननुरूपता, असंगतता, अयोग्यता. **-v. t.** अयुक्तं संबंध् 9 P or संयुज् 7 U, 10. **-ed, -ate,** *a.* विषम, अननुरूप, असम, अयोग्य, अतुल्यगुण, अतुल्य, अनुपयुक्त, असंगत, असंवादिन्. **-ately,** *adv.* अननुरूपं, असमं, अयुक्तं. **-ateness,** *s.* वैषम्यं; *See* (*s.*)

Disprove, *v. t.* प्रत्याख्या 2 P, निराकृ 8 U, निरस् 4 U, खंड् 10, बाध् 1 A; *See* **Confute.** **-Disproof,** *s.* खंडनं, निरसनं, बाधः-धा, निराकरणं, प्रत्याख्यानं. **2** अनिर्णयः, अनिश्चयः, अप्रमाणं.

Dispute, *v.* विवद् 1 A, कलहायते (D.), विप्रतिपद् 4 A, विप्रलप् 1 P, वितर्क् 10; 'what are you d. ing about' किमर्थं विवदध्वे, किं वः विवादवस्तु. **2** विचर् c., गुरोराज्ञा अविचार्या 'not to be d. ed' विकृप् c. **-s.** विवादः, कलहः, वादः; विप्रलापः, विप्रतिपत्ति *f.*, वितर्कः, वाग्युद्धं, वाक्युद्धं, वितंडा; 'subject under d.' विवादवस्तु, विवादास्पदं ; 'it is a d. ed point' वादग्रस्तोर्थः. **-ant, -er,** *s.* तर्किन् *m.*, विवादिन् *m.*, हेतुवादिन् *m.*, नैयायिकः; तार्किकः, 'a d. might ask' ex. by ननु (followed by अत्रोच्यते or उच्यते) or अत्र कश्चित् प्रत्यवतिष्ठेत. **-ation,** *s.* वादः, तर्कः; *See* (*s.*). **-atious,** *a.* कलहशील, वादप्रिय, विवादार्थिन्, कलहप्रिय-काम.

Disqualify, *v. t.* अक्षम-अयोग्य *a.* कृ 8 U, अपात्रीकृ. **-ication,** *s.* निर्गुणः, प्रत्यूहः, अपात्रता, अक्षमता.

Disquiet, *v. t.* आकुलीकृ 8 U, बाध् 1 A, संपीड् 10, क्षुभ् c., उद्विज् c., मुह् c. **-s. -ness, -ude,** *s.* चिंता, उद्वेगः, आकुलत्वं, व्यग्रता, संभ्रमः, बाधा, औत्सुक्यं, वैक्लव्यं, क्षोभः, व्यामोहः, अनिर्वृति *f.* **-ed,** *a.* उद्विग्न, अनिर्वृत, क्षुब्ध, आकुल, व्यग्र, मूढ, संभ्रांत.

Disquisition, *s.* विचारः, परीक्षा, विवेचनं, विमर्शः, निरूपणं.

Disregard, *v. t.* उपेक्ष् 1 A, अवधीर् 10,

स्कृ 8 U, धिक्कृ, न श्रु 5 P, न आदृ 6 A, न अपेक्ष् 1 A. —*s.* उपेक्षा, अनादरः, अवधीरणा, अवज्ञा, अनपेक्षा, अनवधानं, निरपेक्षता. —**ful,** *a.* निरपेक्ष, अनवधान, मंदादर, उपेक्षक, अवमानिन्. —**fully,** *adv.* निरपेक्षं, उपेक्षया, अनपेक्ष्य.

Disrelish, *s.* अरुचि *f.*, विरागः, विरक्ति *f.*, विमुखता, अप्रीति *f.*, विद्वेषः. —*v. t.* विद्विष् 2 U, न रुच् 1 A.

Disrepute, -ation, *s.* अ-अप-कीर्ति *f.*, अयशस् *n.*, अप्रतिष्ठा, वाच्यता अपमानः. —**able,** *a.* अकीर्तिकर (री *f.*), अनार्य, गर्हित, अयशस्कर, कलंककर, निंद्य, दूषणीय.

Disrespect, *v. t.* न आदृ 6 A, अवमन् 4 A, उपेक्ष् 1 A, अवज्ञा 9 U, अवगण् 10, न मन् c. ; *See* **Contemn.** —*s.* अवज्ञा, अनादरः, अवमानः, अवधीरणं-रणा, उपेक्षा, परिभवः, तिरस्कारः. —**ful,** *a.* सावज्ञ, उपेक्षक, परिभाविन्, अवमानिन्.

Disrobe, *v. t.* विवस्त्रीकृ 8 U, वस्त्रं अपकृष् 1 P, विवस्त्रयति (D.).

Disrupt, *v. t.* भंज् 7 P. विदॄ 10, भिद् 7 P. —**ion,** *s.* भंगः, विदारणं, भेदः.

Dissatisfy, *v. t.* असंतोषं-अतुष्टिं-उत्पद् c. or जन् c. (जनयति) ; न संतुष् c., न तृप् c.; अप-वि-रंज् c. —**ed,** *a* अतृप्त, विरक्त, वितुष्ट, असंतुष्ट, अपरक्त. —**Dissatisfaction,** *s.* अतुष्टि *f.*, असंतोषः, विरक्ति *f.*, अप-वि-रागः.

Dissect, *v. t.* (अंगानि) व्यवच्छिद् 7 P, निकृत् 6 P, पृथक् कृ 8 U. **2** सूक्ष्मं विचर् c. or परीक्ष् 1 A. —**ion,** *s.* व्यवच्छेदः, अंगच्छेदः, **2** सूक्ष्मपरीक्षणं. —**or,** *s.* व्यवच्छेदकः.

Dissemble, *v. t.* अप-व्यप-दिश् 6 P. नि-अपह्नु 2 A; *See* **Conceal.** —**er,** *s.* छाद्मिकः, दांभिकः, व्यपदेशकः, छद्म कपट-वेशिन् *m.* —**ing,** *s.* अपह्नवः, प्रतारणा, गोपनं, अपलापः, छद्मन् *n.*, दंभः, कपटं.

Disseminate, *v. t.* वि-प्र-कॄ 6 P, प्रसृ c., विसृज् c., प्रचर् c., निवप् 1 P. —**ion,** *s.* प्रसारः, प्रसरणं, विस्तारः, प्रचारणं. —**or,** *s.* प्रचारकः, प्रसारकः

Dissent, *v. i.* विवद् 1 A, विसंवद् 1 P, न संमन् 4 A, अन्यथा मन्, अन्यमत *a.* भू. —*s.* वैमत्यं *f.*, असंमति *f.*, मतिभेदः, विमतिः *f.*, विसंवादः विरोधः, विप्रतिपत्ति *f.* —**er,** *s.* भिन्नमतावलंबिन् *m.* **2** साधारणधर्मविरोधिन् *m.* —**ient,** *a.* विमत, भिन्नमत. असंवादिन्; 'without one d. voice', सर्वेषामैकमत्येन.

Dissension, *s.* भेदः, कलहः, कलिः, विरोधः, विप्रतिपत्ति *f.*, विवादः; 'seeds of d.' कलहबीजं ; 'sowing d.' उपजापः, भेदः; 'a sower of d.' उपजापकः, भेदकः; 'family d.s' गृहच्छिद्रं-द्रं, अंतर्भेदः.

Dissertation, *s.* विवरणं, वर्णनं, प्रबंधः, निबंधः.

Disserve, *v. t.* अपकृ 8 U, न उपकृ, हिंस् 7 P. —**ice,** *s.* अपकारः, क्षति *f.*, अपायः, हानि *f.*

Dissever, *v. i.* वियुज् 7 A, 10, विच्छिद् 7 P, विश्लिष् c.

Dissident, *a.* विमत, भिन्नमत.

Dissimilar, *a.* भिन्न, असदृश (शी *f.*), विरुद्ध, असम, विजातीय, विषम. —**ity,** *s.* असादृश्यं. भेदः, वैधर्म्यं, अंतरं, विजातीयत्वं.

Dissimulation, *s.* छलं, कपटं, छद्मन् *n.*, माया; *See* **Pretext.**

Dissipate, *v. t.* वि-प्र-कॄ 6 P, विक्षिप् 6 P, अपास् 4 P; *See* **Dispel. 2** व्यय् 10 P (व्यययति), अपचि 5 U, क्षै c (क्षपयति). —**ed,** *a.* प्रकीर्ण, निर्धूत, अपास्त. **2** दुराचार, व्यसनासक्त, नष्टचरित्र, भ्रष्टशील, दुर्वृत्त, खंडितवृत्त. —**ion,** *s.* विकिरणं. **2** धनव्ययः, द्रव्योत्सर्गः, अपव्ययः. **3** व्यसनिता, भ्रष्टशीलता, दुर्वृत्तता.

Dissociate, *See* **Separate.**

Dissolve, *v. t.* विली c., विद्रु c. **2** भिद् 7 P or c., वियुज् 7 A, 10, भंज् 7 P, विनश् c., विलुप् c., उच्छिद् 7 P; विघट् c. ; 'd. a meeting' सभां विसृज् 6 P or c. ; 'd. friendship' सौहृदं भिद् or त्रुट् c or विघट् c. ; 'd. a compound' समासं विग्रह् 9 P. —*v. i.* ली 4 A, वि-प्र°, (लवणं जले विलीयते); विद्रु 1 P, गल् 1 P, क्षर् 1 P. द्रवीभू 1 P —**able,** —**Dissoluble,** *a.* विद्राव्य, क्षरणशील, विलयनशील. —**ent,** *a.* विलयन (नी *f.*), विद्रावक. —**Dissolute,** *a.* तरल, अनवस्थित, उद्दाम, उच्छृंखल, निर्यंत्रण. **2** दुराचार, भ्रष्टशील, भोगासक्त, व्यसनिन्, दुर्वृत्त, विषयिन्, कामुक, विषयनिरत, इंद्रियसुखनिरत-तत्पर. —**ly,** *adv.* कामुकवत्, विषयासक्तवत्. —**ness,** *s.* विषयासक्ति *f.*, दुर्वृत्तता, भोगासक्ति *f.* —**Dissolution,** *s.* विलयनं, द्रवीकरणं-भवनं. **2** प्रलयः, नाशः, क्षयः, विध्वंसः, उच्छेदः. **3** भंगः, वियोगः, निवृत्ति *f.*, विग्रहः, विच्छेदः. विघटनं.

Dissonance, *See* **Discord.**

Dissuade, *v. t.* निवार् 10, निवृत् c., व्यावृत् c., (नैनमस्माद् व्यवसायाच्छक्यते व्यावर्तयितुं Ka. 172); नियम् 1 P, (सुतां शशाक मेना न नियंतुमुद्यमात् K. v. 5); नि-प्रति-षिध् 1 P, (उ मेति मात्रा तपसो निषिद्धा K. I. 26); प्रत्यादिश् 6 P. —**er,** *s.* निवारकः, निवर्तयितृ *m.*, निषेधकः, प्रत्यादेष्टृ *m.* —**Dissuasion,** *s.* निवर्तनं, नियमनं, प्रत्यादेशः, निषेधः-धनं, निवारणं. —**Dissuasive,** *a.* व्यावर्तक, निषेधक, प्रत्यादेशक· निवृत्तिहेतुः.

Dissyllable, *s.* द्व्यक्षरं, द्व्यक्षरः शब्दः.

Distaff, *s.* तर्कु *m. f.*, तर्कुटी.

Distance, *s.* (Space) अध्वन् *m.*, भूमि *f.*; 'by what d. separated' कियताध्वना विच्छिन्न. 2 अंतरं, अंतरालं, व्यवधानं. 3 विप्रकर्षः, दूरता, असान्निध्यं, दूरं; 'from a d.' दूरात्, आरात्; 'at a d.' दूरे-रं, दूरतः; 'at the d. of a mile' अर्धक्रोशमात्रायां (Ka. 74). 4 दुरासदत्वं, अनालापः, दुर्धर्षता, संवृतशीलत्वं. –*v. t.* दूरीकृ 8 U, अपसृ c. 2 Excel, q. v. **–Distant,** *a.* दूरस्थ, अंतरवर्तिन्, दूर, विप्रकृष्ट, असन्निकृष्ट दवीयस्; 'a d. relation' विप्रकृष्टो बांधवः. 2 दुरासद, दुर्धर्ष; अगम्य; अनालापिन्.

Distaste, *s.* अरुचि *f.*, विरक्ति *f.*, विरागः, वितृष्णा, अप्रीति *f.*, अननुरागः, विद्वेषः. –*v. t.* न रुच् 1 A (with dat.). **–ful,** *a.* अस्वादु, अरुचिकर (री *f.*), अप्रिय, अनिष्ट.

Distemper, *s.* Disease, q. v. 2 व्यथा, क्लेशः, बाधा, तापः, अनिर्वृति *f.* 3 दुःशीलं, कुस्वभावः, असद्भावः, दुर्दशा. –*v. t.* पीड् 10, बाध् 1 A, क्लिश् 9 P, उपहन् 2 P. **–ed,** *a.* व्याधिग्रस्त, आतुर, रुग्ण, पीडित, आर्त, आकुल.

Distend, *v. t.* वितन् 8 U, विस्तृ c., श्वि c., आध्मा 1 P, स्फाय् c. (स्फावयति); 'd.-ed with wind' वातपूरित, वातोच्छून, मारुताध्मात. **–Distension,** *s.* विस्तारः, स्फीति *f.*, आध्मानं, पूरणं.

Distich, *s.* श्लोकः, द्विचरणं; द्विपदं.

Distil, *v. i.* क्षर् 1 P, स्रु 1 P, स्यंद् 1 A, श्चुत्-श्च्युत्- 1 P. –*v. t.* स्रु c., स्यंद् c., सुत्-स्रुच्- 6 P, अवपत् c. 2 (Spirit) संधा 3 U, निष्कुष् 1 P, आ-अभि-सु 5 P. **–lation,** *s.* क्षरणं, द्रवणं, निस्यंदः, स्रवः, स्रवः. 2 अभिषवः, मद्यसंधानं, मद्यनिष्कर्षः. **–er,** *s.* शौंडिकः, सुराजीविन् *m.*, सुराकारः. **–lery,** *s.* संधानी, मद्यनिष्कर्षशाला, शुंडा.

Distinguish, *v. t.* वि-विच् 3, 7 P or c., परिच्छिद् 7 P, विभिद् 7 P, विशिष् 7 P or c., विभज् 1 U, विशेषं कथ् 10. 2 विद् c., लक्ष् 10, विज्ञा 9 U, अभि-ज्ञा. 3 (Oneself) उत्कर्ष-कीर्ति-प्रतिष्ठां-लभ् 1 A, विख्यात *a.* भू 1 P. **–ed,** *a.* विविक्त, परिच्छिन्न; विभिन्न. 2 लक्षित, चिह्नित, विज्ञात. 3 विशिष्ट, विश्रुत, प्रसिद्ध; विशेष in comp.; अतिथिविशेषः 'a d. guest'; 'men are d. from the lower animals by knowledge' नराणां तिरश्चां च प्रतिबोध एव विशेषः. **–Distinct,** *a.* भिन्न, विविक्त, विशिष्ट, व्यतिरिक्त, पृथग्विध, अन्य-इतर- (*pron. a.*), पृथक् *ind.* 2 स्पष्ट, परिस्फुट, व्यक्त, सुप्रकाश. **–ion,** *s.* विशेषः, भेदः, प्र-वि-भेदः, अंतरं, पृथक्त्वं, भिन्नता. 2 परिच्छेदः, विवेकः, विवेचनं, विचारः-रणा. 3 प्रतिष्ठा, गौरवं, वर्णः, ख्याति *f.*, विशिष्टता, उत्कर्षः, प्रमुखत्वं, परमपदं. **–ive,** *a.* विशेषक, सविशेष, परिच्छेदक; 'a d. mark' विशेषचिह्नं, विशिष्टलिंगं. **–ively,** *adv.* सविशेषं, विशेषेण, पृथक् पृथक्. **–ly,** *adv.* पृथक्, विभिन्नं. 2 व्यक्तं, सुस्पष्टं, स्पष्टार्थं, भिन्नार्थं, परिस्फुटं. **–ness,** *s.* भिन्नता. 2 व्यक्ति *f.*, स्पष्टता, भिन्नार्थत्वं.

Distort, *v. t.* आकुंच् c., साचीकृ 8 U, वक्रीकृ. 2 विरूप् 10, वि-कृ, व्यंगीकृ, कदाकारीकृ. 3 परिवृत् c., दुष् c. (दूषयति). **–ion,** *s.* साचीकरणं, वक्रता, परिवर्तनं. 2 विरूपकरणं, विकृति *f.*, आकुंचनं, वैरूप्यं, व्यंगता, कुरूपता.

Distract, *v. t.* आकुलीकृ 8 U, व्यामुह् c., संभ्रम् (भ्रमयति), उन्मद् c., विक्षिप् 6 P, अप-वि-कृष् 1 P, संक्षुभ् c. 2 विदृ 10, खंड् 10, विभिद् 7 P, विदल् c (दलयति). **–ed,** *a.* विक्षिप्त, मोहित, व्यग्र, विधुर, आकुल, मूढ, विह्वल, संक्षुब्ध, भ्रांत, उन्मत्त; 'of a d. mind' भ्रांतचित्त, वातुल; 'to be d.' मुह् 4 P, उन्मद् 4 P. **–edly,** *adv.* मूढचेतसा, व्यग्रं, उन्मत्तवत्, ससंभ्रमं. **–ion,** *s.* भ्रमः, आकुलत्वं, विह्वलता, व्या-,मोहः, क्षोभः, व्यग्रता, उन्मादः. 2 विभेदः, विदारणं.

Distrain, *v. t.* ऋणहेतोः बंध् 9 P or निरुध् 7 U.

Distraught, *a.* *See* **Distracted.**

Distress, *s.* दुःखं, शोकः, क्लेशः, कष्टं, पीडा, दुर्गति *f.*, वैक्लव्यं, आर्ति *f.* 2 आपद् *f.*, विपद् *f.*, व्यसनं, वि-उप-प्लवः; 'cry of d.' आर्तरवः-क्रंदितं. –*v. t.* पीड् 10, व्यथ् c., क्लिश् 9 P, बाध् 1 A, दुःखयति (D.), संतप् c., खिद् c. **–ed,** *a.* व्यथित, आर्त, दुःखित, पीडित, कष्टापन्न, कृच्छ्रगत, दुर्गत, विपन्न, विधुर, दीन, क्लेशभाज्. **–ful,-ing,** *a.* शोकावह, कष्टप्रद, क्लेशद, पीडा-क्लेश-कर (री *f.*); दुःख-मय (यी *f.*), खेदक.

Distribute, *v. t.* विभज् 1 U, वंट् 10, वि-अंश् 10, विभागशः दा 3 P or परिकल्प् c., यथाभागं विसृज् 6 P or विन्यस् 4 U or निक्षिप् 6 P; 'd. food' अन्नं परिविष् 10, **–er,** *s.* विभागकल्पकः, विभक्तृ *m.*, अंशदः; 'd. of food' परिवेष्टृ *m.* **–ion,** *s.* विभागः, संप्रविभागः, विभागकल्पना, व्यंशनं, वंटनं.

District, *s.* देशविभागः, प्रांतः, मंडलं, चक्रं, प्रदेशः.

Distrust, *v. t.* आ-परि-शंक् 1 A, न विश्वस् or प्रति-इ 2 P. –*s.* अविश्वासः, अप्रत्ययः, आशंका. **–ful,** *a.* साशंक, शंकाशील, अप्रत्ययिन्, अविश्वासिन्. **–fully,** *adv.* साशंकं, अविश्वासेन.

Disturb, *v. t.* आकुलीकृ 8 U, धू 5, 9 U. उपरुध् 7 U, क्षुभ् c., बाध् 1 A; *See* **Agitate.** 2 भंज् 7 P, प्रतिबंध् 9 P, भिद् 7 P, विहन् 2 P, विच्छिद् 7 P; 'd. sleep' निद्राभंगं कृ; 'd. studies' अध्ययनविघ्न-

साधय् 1 P; 'able to d. penance' तपो भेदायालं. 3 (Mind) व्याकुल् c, आकुलीकृ, आकुलयति (D.), संभ्रम् c., वि-कृ. -ance, s. क्षोभः, सं-वि-क्षोभः, विप्लवः, विमर्दः, पीडा. 2 प्रतिबंधः, प्रत्यूहः, अंतरायः, विघ्नः, विच्छेदः, भंगः, बाधा, भेदः; 'd. of concentration' समाधिभेदः; 'popular d.' प्रकृतिक्षोभः-कोपः; 'cause of d. विकारहेतुः. 3 मोहः, आकुलता, व्यग्रता, वैक्लव्यं, संभ्रमः. -er, s. क्षोभकृत् m., विघ्नकरः.

Disunite, *v. t.* वियुज् 7 A, 10 विश्लिष् c.; *See* **Separate.** -*v t.* वियुज्-विश्लिष्-विभिद् pass. **-Disunion,** *s.* वियोगः, विश्लेषः, विभेदः, विच्छेदः.

Disuse, Disusage, *s.* अव्यवहारः. विलोपः, विरामः; व्यवहारनिवृत्ति *f.*, अप्रचारः, आचारलोपः; 'fallen into d.' विलुप्त, लुप्तव्यवहार. -*v. t.* व्यवहाराद् विरम् c. or निवृत् c.

Ditch, *s.* परिखा, खातं, गर्तः-र्ता, उपकुल्या, प्रणालः-ली, प्रतिकूपः. -*v. t.* परिखन् 1 P, गर्तां कृ 8 U. -er, *s.* खातकारः, आखानिकः.

Ditto, *adv.* तथा; 'says d.' तथैव ममाभिप्राय इति वदति. -*a.* पूर्वोक्त, प्राग् लिखित, प्रागुक्त.

Ditty, *s.* गीतं, गीति *f.*, गीतिका, गानं, गानखंडः.

Diuretic, *a.* मूत्रवर्धक.

Diurnal, *a.* आह्निक दैनिक (की *f.*), दैनंदिन (नी *f.*); *See* **Daily.**

Diuturnal, *a.* चिरकालिक(की *f.*)चिरस्थायिन्.

Divagation, *s.* *See* **Digression,** उत्पथविमार्ग-गमनं.

Divan, *s.* शिष्टसभा. 2 इंद्रकं, मंचयुक्तः प्रकोष्ठः, आस्थानं-नी. 3 मंचः.

Divaricate, *v. i.* द्विधा भू 1 P, द्विखंडीभू, द्विधा विभिद् pass. -*v. t.* द्विधा कृ 8 U, द्विधा भिद् 7 P.

Dive, *v. i.* वि-अव-गाह् 1 A, निमस्ज् 6 P, विश् 6 P, प्लु 1 A; 'd. ing into books' ग्रंथपरायण, ग्रंथमग्न-निविष्ट. -er, *s.* विगाहकः, निमक्तृ *m.*; 'river d.' नदीष्णः, जलेवाहः.

Diverge, *v. i.* (एककेंद्राद्) विचल् 1 P, च्यु 1 A, व्युत्क्रम् 1 U, 4 P, भ्रंश् 1 A, 4 P; *See* **Deviate,** also. 2 **Differ,** q. v. -ence, *s.* विचलनं, च्युति *f.*, केंद्रापसरणं, भ्रेषः, भ्रंशः. 2 भेदः, विरोधः. -ent, *a.* केंद्रविचल. 2 विभिन्न, विरुद्ध.

Diverse, (Divers), *a.* अनेक, विविध, नानारूप-प्रकार-विध, नाना *ind.* 2 भिन्न, इतर-अन्य- (*pron. a.*), असम, विपरीत, पृथक् *ind.*; 'd. coloured' नानावर्ण, चित्र, कर्बुर, कल्माषित. -ity, *s.* पृथक्त्वं, नानाविधत्वं, भिन्नता, नानात्वं, विभेदः, असादृश्यं, असाम्यं, वैरूप्यं. 2 वैचित्र्यं, विचित्रता. -ly, *adv.* अनेकधा, नानाविधं, नानारूपेण, नाना. **-Diversify,** *v. t.* चित्र् 10, नानारूप *a.* कृ 8 U, शबलीकृ, *See* **Variegate.** -ed, *a.* कर्बुरित, नानाप्रकार, शबल, कल्माषित, चित्र, चित्रित. -ication, *s.* विचित्रता, विविधत्वं, विभेदः.

Divert, *v. t.* विमुह् c., रंज् c., नंद् c., रम् c. (रमयति); 'd. oneself' वि-हृ 1 P, क्रीड् 1 P. 2 व्या-वृत् c., आ-वि-कृष् 1 P, भ्रंश् c., संचर् c., संक्रम् c., आक्षिप् 6 P, प्र-वि-चल् c., च्यु c.; 'I shall d. his thoughts' एवं तावद्वाक्षिपामि (Mal. 9), अन्यतः संचारयामि (U. 1.). -ing, *a.* विनोदक, हासजनक, नर्मप्राय, क्रीडापर. **-Diversion,** *s.* विनोदः-दनं, विहारः, क्रीडा, विलासः, केलि *f.*, खेला, विभ्रमः. 2 मनोरंजनं, मनोविनोदनं. 3 विकर्षणं, भ्रंशनं, व्यावर्तनं, आक्षेपणं.

Divest, *v. t.* हृ 1 P, अपनी 1 P; *See* **Deprive.** 2 विवस्त्रीकृ 8 U, उच्छद् 10, वस्त्रं अपनी or उत्कृष् 1 P. -ure, *s.* अपहरणं; विवस्त्रीकरणं.

Divide, *v. t.* विभिद् 7 P, विच्छिद् 7 P; वि-युज् 7 A, 10, विश्लिष् c., पृथक् कृ 8 U, शकलीकृ. 2 प्र-,सं-,विभज् 1 U, परिक्लृप् c.; 'd. ed in half अर्धे विच्छिन्न (S. 1); 'd. into 2, 3, parts' &c. द्विधा-,त्रिधा-, कृ; मुख्यानामवयवशो विभज्यमानानां (S. B. 533) 'when d. ed into parts' &c. 3 (In Math.) भज्, विभज्, हृ 1 P; 'd. ing by the remainder' शेषेण हृत्वा-विभज्य. -*v. i.* विश्लिष् 4 P, विभिद्-विच्छिद् pass., द्विधा भू 1 P. 2 दल् 1 P, स्फुट् 6 P; 'they were d. ed in opinion' ते भिन्नमता आसन्, द्वैधीभूताः; 'a house d. ed against itself' अंतर्भेदाकुलं गृहं. -er, *s.* विभेदकः, विच्छेदकः, विभागकल्पकः. **-Dividend,** *s.* भागः, अंशः, उद्धारः, लाभः. 2 भाज्यः. **-Divisor,** *s.* हरः, हारः, भाजकः, हर(हा)रकः. **-Division,** *s.* विच्छेदः, विभेदः, खंडनं, पृथक्करणं, वियोगः, विश्लेषः, दलनं. 2 भिन्नता, विभक्तता. 3 विभागः, अंशनं, विभाग-परिकल्पनं, उद्धारः. 4 भागः, खंडः, एकदेशः, विभागः. 5 भागहरः, हरणं, भाजनं; 'd. of an army' गुल्मं, वृन्दं. **-Divisible,** *a.* विभाज्य, विच्छेद्य, विभेद्य.

Divine, *a.* दिव्य, दैव (वी *f.*), देव (वी *f.*), ऐश्वर (री *f.*), अमानुष (षी *f.*), अपार्थिव (वी *f.*), 2 ईश्वरतुल्य. -*s.* पुरोहितः, धर्मोपदेशकः, श्रोत्रियः. -*v. t.* लक्षणानि or शकुनानि परीक्ष् 1 A, शुभाशुभं आलोच् 10 or कथ् 10 or प्रमृश् c. 2 (Guess) ऊह्

1 A, अनुमा 3 A, 2 P, अवगम् 1 P, तर्क् 10. -ation, s. शकुनपरीक्षणं, लक्षणपरीक्षणं, भविष्यसूचनं. 2 अनुमानं, तर्कः. -er, s. दैवज्ञः, शकुनपरीक्षकः, निमित्तज्ञः. 2 अनुमातृ m. -ity, s. दैवत्वं, दिव्यता, देवतानुभावः. 2 देवता; See God. 3 परमार्थविद्या, श्रुतिविद्या ईश्वरविषयं शास्त्रं. -ly, adv. देववत्, दिव्यरूपेण.

Divorce, v. t. त्यज् 1 P, निराकृ 8 U, निरस् 4 U; विवाहं लुप् c. or भिद् 7 P. -s., -ment, s. त्यागः, निराकरणं, विवाहलोपः, प्रत्यादेशः; विवाहोच्छेदः.

Divulge, v. t. प्रकाश् c., प्र-ख्या c. (ख्यापयति), वि-वृ 5 U, भिद् 7 P or c. -er, s. प्रकाशकः, भेदकः. -ing, s. प्रकाशनं, विवरणं, भेदः.

Divulsion, s. विवरणं, उत्पाटनं.

Dizzy, a. भ्रमिन्, घूर्णमान. 2 भ्रमकारक, भ्रमकर (री f.), भ्रमोत्पादक. 3 चपल, प्रमत्त, अनवहित. -ness, s. घूर्णनं, घूर्णि f., भ्र(भ्रा)मरं, भ्रमः, भ्रमि f..

Do, v. t. कृ 8 U, विधा 3 U, संपद् c., अनुष्ठा 1 P, निर्वृत् c., आचर् 1 P, निर्वह् c., प्र-णी 1 P, प्रतिपद् 4 A, (किमधुना प्रतिपत्स्ये). 2 जन् c., (जनयति), उत्पद् c., साध् c.; 'd. one's best' यथाशक्ति कृ 3 (Standing for verb) ex. by the verb or by circum.; 'speak as you are accustomed to d.' यथाभ्यस्तमभिधीयतां (U. 1). 4 (As emphatic) ex. by एव, नूनं, खलु, किल; आजगाम किल, तिष्ठत्येव, &c. -v. i. आचर् 1 P, व्यवहृ 1 P, वृत् 1 A; 'd. unto others' अन्येषु व्यवहर, वर्तस्व. 2 भू 1 P, अस् 2 P, स्वस्थ-कुशलिन् a. भू; 'how do you d.' अपि कुशलं भवतः, कस्ते वृत्तांतः; 'asks you how you d.' त्वां सुखं-कुशलं पृच्छति; 'd. well' सुस्थित a भू; देवी सुख प्रसूमागता (M. 4) 'to ask if she was d. ing well &c.' 3 (At the end of a speech); 'I have done' अवसितवचनोस्मि; साधयामि; 'this carelessness will not d.' ईदृशं प्रमादित्वं न मया क्षंतव्यं or न ते हिताय कल्प्यते; 'that will d. now' अलमलं, विरम, इत्यलं; 'this will d. as water for washing the feet' इदं पादोदकं भविष्यति (S. 1); 'it will d. just as well for you' एवमपि तव समीहितं सिद्धमेव. -away, विनश् c., लुप् c.; 'd. away with' अलं, कृतं (with instr.); 'have done with your importunity' अलं निर्बंधेन. 2 Kill, q. v.; अपह् 1 P (life &c.). -with, Ex. by किं, किं कार्यं, or प्रयोजनं with instr.; 'what can you d. with such a servant' ईदृशेन भृत्येन किं तव कार्यं, 'what have we to d. with watching the movements of our master' किमस्माकं स्वामिचेष्टानिरूपणेन (H. 2). 2 प्र-उप-युज् 10, व्याप् c. -without, Dispense with, q. v. -er, s. कर्तृ m., कारकः-करः-कारः, कृत्-in comp.; संपादकः, निर्वर्तयितृ m., निर्वाहकः. -ing, s. करणं, विधानं, संपादनं; 'of one's own d.' आत्मकृत, स्वयंकृत. 2 (D. s) चरितं, चेष्टितं, कार्यं, व्यापारः. 3 व्यवहारः, आचारः, प्रवृत्ति f.

Docile, a. विनेय, अनुविधायिन्, विधेय, वश्य, अधीन, आयत्त, शिष्य. -Docility, s. विनेयता, वश्यता.

Dock, s. छिन्नपुच्छं. 2 नौकागारं, नावाश्रयः. -v. t. (पुच्छं) छिद् 7 P, लू 9 U, कृत् 6 P.

Docket, s. सूचिपत्रं, अर्थिनामावली. 2 अंकपटः, अंकपत्रं.

Doctor, s. भिषज् m., वैद्यः, चिकित्सकः; अगदंकारः, जीवदः, रोगहारिन् m. 2 पंडितः, बहुश्रुतः, शास्त्रज्ञः, ex. by आचार्य in comp. 3 शिक्षकः, आचार्यः, गुरुः. -v. t. Treat, q. v. -ship, s. आचार्यपदं, गुरुपदं.

Doctrine, s. मतं. 2 तत्त्वं, न्यायः. 3 पथिन् m., पथ in comp.; मार्गः. 4 (System) वादः; 'd. of evolution' परिणामवादः; प्रधानकारणवादः, अनीश्वरवादः, &c.; 'receive d. s' संप्रदायः, आम्नायः.

Document, s. लेख्यं, लेखः, पत्रं, पत्रकं, लेख्यपत्रं. -ary, a. (s.) in comp.; 'd. evidence' लेख्यप्रमाणं.

Dodecagon, s. द्वादशास्रं, द्वादशकोणः.

Dodge, v. t. वंच् 10, प्रेर् c.; See Cheat. -v. i. छलेन अपक्रम् 1 U, 4 P, विपरिवृत् 1 A. -s. छलं, कपटोपायः, शाठ्यं, कपटं.

Doe, s. मृगी, हरिणी, एणी, पृषती, कुरंगी.

Doff, v. t. (वस्त्रं) अपनी 1 P, अवरुह् c., उन्मुच् 6 P.

Dog, s. श्वन् m. कुक्कुरः, सारमेयः, शुनकः; कौलेयकः, भषकः, मृगदंशकः; 'd. -cheap' अतिस्वल्पमूल्य; 'd. days' अत्युष्णकालः; 'mad d.' अलर्कः; 'go to the d.s' विनश् 4 P, परिक्षि pass.; 'hunting d.' विश्वकद्रुः. -v. t. (कुक्कुरवत्) अनुसृ 1 P पश्चात् धाव् 1 P, अन्विष् 4 P, अनुसृत्य पीड् 10. -gish, a. श्वशील, श्ववृत्ति, श्वभाव.

Dogged, a. कठिन, निष्ठुर, वक्रभाव. 2 प्रतिनिविष्ट, साग्रह. निर्बंधपर.

Doggerel, a. विषम; 'd. verses' कुकाव्यं

Dogma, s मतं, तत्त्वं, नियमः, व्यवस्था, विधिः, आदेशः. -tic, -tical, a. स्वमताभिमानिन्, निश्चयात्मक; वैधिक (की f.). -ally, adv. दृढविश्वासपूर्वं, सदर्पं, साहसेन, सगर्वं च

-tism, *s.* स्वमताभिमानः, सधर्षं, स्वमतावलंबनं, दुराग्रहोक्ति *f.* **-tize,** *v. t.* सधर्ष-सगर्वं-स्वमतं संस्था c. (स्थापयति) or वद् 1 P.

Dole, *s.* अंशः, भागः, विभागः, छेदः, उद्धारः. 2 पारितोषिकं. **-v. t.** विभज् 1 U, विभागशः दा 3 U, वितॄ 1 P, उत्-सृज् 6 P. **-ful, -some,** *a.* सशोक, दुःखपूर्ण, सकरुण, शोकाकुल, उद्विग्न, विधुर, आकुल, विह्वल, आर्त. **-fully,** *adv.* सशोकं, सदुःखं, सविषादं. **-fulness,** *s.* शोकः, दुःखं, विषादः, खेदः, उद्वेगः, परिदेवनं.

Doll, *s.* शालभंजिका, पांचालिका, पांचाली, कुरुंटी, पुत्रिका ; 'ivory d.' दंतपांचालिका.

Dolour, *s.* शोकः, क्लेशः, खेदः, आर्ति *f.* **-ous,** *a.* सशोक, शोकार्त, उद्विग्न, आकुल, विधुर. **-ific,** *a.* पीडा-व्यथा-कर (री *f.*)

Dolphin, *s.* स्थूलमीनः, मत्स्यभेदः.

Dolt, *s.* स्थूल-मंद-बुद्धिः, मूढः, मूर्खः, जडः. **-ish,** *a.* मूढ, स्थूल मति-धी. **-ishly,** *adv.* मूढवत्, स्थूलवत्.

Domain, *s.* राष्ट्रं, विषयः, प्रदेशः. 2 राज्यं, स्वामित्वं. 3 रिक्थं, स्वभूमि *f.*

Dome, *s.* अर्धगोलाकृति शृंग-शिखरं.

Domestic, *a.* ग्राम्य, ग्राम-गृह-in comp.; ग्रामसिंहः 'd. lion'; 'd. pigeon' गृहकपोतः. 2 गृहज, गृह्य, गृहजात, गृह in comp.; 'd. quarrels', गृहकलहाः, गृहच्छिद्राणि; 'd. duties' कुलाचारः; 'd. dissension' अंतर्भेदः. 3 गृहप्रिय, गृहवासासक्त. 4 देशीय, देश in comp. **-s.** गृहदासः, किंकरः, प्रेष्यः, भृत्यः, सेवकः, परिचरः. 2 गृहवासिन् *m.* **-ate,** *v. t.* विनी 1 P, दम् c. (दमयति), गृहे पुष् c. or संवृध् c. **-ated,** *a.* गृहपुष्ट, दांत, ग्राम्य.

Domicile, *s.* गृहं, आ-नि-वासः, आलयः, वसति *f.* **-ed,** *a.* कृतावास, कृताधिष्ठान.

Dominant, *a.* प्रबल, प्रधान, प्रकृष्ट, श्रेष्ठ, प्रभविष्णु, सातिशय, वरीयस्.

Dominate, *v. i.* शास् 2 P; प्रभू 1 P, ईश् 2 A (with gen.), अधिष्ठा 1 P, अध्यास् 2 A. 2 अतिरिच् pass.; प्रकृष्ट *a.* भू. **-ion,** शासनं, प्रभुत्वं, आधिपत्यं, राज्यं, अधिकारः.

Domineer, *v. t.* सगर्वं शास् 2 P, or ईश् 2 A (with gen.), कदर्थ् 10, पीड् 10, उपक्रु 1 A. **-ing 2** *a.* उद्धत, अवलिप्त, अतिदृप्त, उत्सिक्त, मदोद्धत.

Dominical, *a.*, *s.* भट्टारकवासरः.

Dominie, *s.* *See* **Tutor.**

Dominion, *s.* अधिकारः, ऐश्वर्यं, प्रभुत्वं, शासनं, आधिपत्यं 2 राज्यं, विषयः, देशः, राष्ट्रं.

Domino, *s.* दीर्घप्रावारः. 2 शलाका.

Don, *s.* सुजनः, आर्यः, शिष्टजनः.

Donary, *s.* धर्मार्थं दत्तं-दानं.

Donation, *s.* दानं, उपायनं, वितरणं, उपहारः, त्यागः, विश्राणनं ; *See* **Gift.**

Donor, *s.* दातृ *m.*, दायिन् *m.*; त्यागशीलः. **-Donee,** *s.* प्रतिग्रहीतृ *m.*

Donkey, *s.* खरः, रासभः, गर्दभः, चक्रीवत् *m.*, वालेयः.

Doodle, *s.* अल्पबुद्धिः, जडः, दुर्मतिः, मंदः.

Doom, *v. t.* दंड् 10, दंडाज्ञां कृ 8 U. 2 निक्षिप् 6 P, सम्-ऋ c. (अर्पयति). 3 निर्दिश् 6 P, सं-प्र-क्लृप् c.; 'how he was d. ed to die' कथं तस्यांतो भविष्यति. 4 निर्णी 1 P, निश्चि 5 U, विचर् c.; 'he is d. ed to death' अस्य वधो निश्चितः, वधदंडः आज्ञप्तः; 'his fate is d. ed' अपरिहार्योऽस्य नाशः. **-s.** दंडाज्ञा, दंडनं, दंडः. 2 निर्णयः, निश्चयः, विचारः-रणा. 3 नियति *f.*, भवितव्यता, दिष्टं, विधिः *m.*; *See* **Fate.** 4 अंतः, नाशः, क्षयः, लयः. **-Doomsday,** *s.* विचारदिवसः.

Door, *s.* द्वारं (fig. also); द्वार् *f.*, प्रति(ती)हारः; 'leaf of a d.' कपाटः-टं-टी, अररः-रं-रि. 2 मुखं, प्रवेशः; 'from d. to d.' गृहाद् गृहं; 'in d. s' गृहे, गृहस्थित *a.*; 'out of d. s' गृहाद्बहिः, स्थानांतरगत *a.*; 'principal d.' महा-सिंह-द्वारं; 'next d.' अनंतर *a.*, प्रातिवेशिक *a.*, निकटस्थ, कल्प in comp., ईषदून; 'private d.' प्रच्छन्नद्वारं; अंतर्द्वारं, 'd.-keeper' द्वाःस्थः, द्वारपालः, द्वाररक्षकः, प्रतीहारः, दौवारिकः ; 'd. sill' द्वारपिंडी, देहलि-ली *f.*, गृहावग्रहणी.

Dope, *v. t.* उन्मद् c., उद्दीप् 10. **-s.** उन्मादकं द्रव्यं. **-y,** *a.* उन्मादित, उद्दीपित.

Dormant, *a.* निद्रित, शयित, सुप्त. 2 अलक्षित, प्रच्छन्न, गुप्त, निलीन, गूढ.

Dormitory, *s.* शय्या-शयन-गृहं, निद्राशाला, शयनागारं.

Dorsal, *a.* पृष्ठसंबंधिन्.

Dose, *s.* मात्रा; 'in one d.' एकयैव मात्रया.

Dot, *s.* बिंदुः, शून्यं, खं. **-v. t.** बिंदुना अंक् 10 or चिह्न् 10.

Dote, (upon), *v. i.* अत्यंतं अभिलष् 1, 4 P, भृशं स्निह् 4 P (with loc.). 2 वृद्धत्वाद् मुह् 4 P, बालिशबुद्धि *a.* भू 1 P. **-age,** *s.* अत्यंतानुरागः, अतिप्रेमन् *m.*, *n.* 2 बुद्धिवैकल्यं, बुद्धिलोपः-भ्रंशः, बालिशता, मतिक्षीणता, जरावैक्लव्यं. 3 जरा, जरावस्था. **-ard,** *s.* क्षीणबुद्धिः, हतज्ञानः, अतिवृद्धः, बालिशः. **-ing,** *a.* अत्यनुरक्त. **-ingly,** *adv.* सातिस्नेहं, अनुरागातिरेकेण.

Double, *a.* द्विगुण, द्वैध (धी *f.*), द्विप्रकार; द्वि in comp., उभय (*pron.a.*). 2 **Deceitful,** q. v.; 'having a d. meaning' द्व्यर्थ (वाक्यं); 'd. meaning' द्व्यर्थता; 'd. dealing' द्वैधीभावः, शाठ्यं, कपटं, छद्मभाषा; 'd.-tongued' द्विजिह्व, असत्यवाद्-

वादिन्. -s. द्विगुणं, द्वित्वं. 2 छलं, कपटं, माया. 3 विपरिवर्तनं. -v. t. द्विगुणीकृ 8 U, गुणीकृ, द्विगुणयति (D.). 2 पुटीकृ, पुटयति (D.); 'd. the fist' मुष्टिं बंध् 9 P. -v. i. द्विगुणीभू 1 P. 2 विपरि-वृत् 1 A. 3 मायां-छलं-कृ. -ness, s. द्वैगुण्यं, द्वित्वं, उभयत्वं. -Doubly, adv. द्विः, द्विगुणं, द्विधा, द्विविधं, उभयतः-था.

Doublet, s. उरोवस्त्रं, उरःपरिधानं.

Doubt, v. i. आ-वि-शंक् 1 A, विकृप् 1 A, संदिह् 2 U, संशी 2 A, विचर् c., मनसा दोलायते (D.). -v. t. न विश्वस् or न प्रति-इ 2 P, आशंक्. -s. संशयः, संशीतिf, संदेहः, शंका, वितर्कः, आशंका, विकल्पः; 'my mind is still in d.' मनस्तु मे संशयमेव गाहते; 'without any d.', 'undoubtedly' असंदेहं, असंशयं, निराशंकं, निःसंशयं, संदेहं विना; अत्र कः संदेहः (in replies). 2 अस्थैर्यं, अनिर्णयः, आंदोलनं, चित्तविभ्रमः. 3 शंका, अविश्वासः, अप्रत्ययः. 4 कृच्छ्रं, विषमं, बाधा, शल्यं, विषमपदं; 'case of d.' संदेहपदं; 'in d.' सशंक-संदेहान्वित-दोलायमान- a. -ful, a. संदिग्ध, शंकनीय, साशंक, शंकान्वित, संशयापन्न, ससंशय; सशयित, संदेहाकुल, संशयावृत, विकल्प्य; संदेहपदं, शंकास्थानं. 2 संदिग्धार्थ, अस्पष्ट; 'to make d.' संदिह् c. -fully, -ingly, adv. ससंदेहं, साशंकं, सविकल्पं. -less, a. निराशंक, निःसंदेह, असंशय. -adv., -lessly, निःसंशयं, असंशयं, विना संदेहेन, निःशंकं.

Douceur, s. पारितोषिकं, उपायनं, उत्कोचः. 2 सौजन्यं, सुशीलता, सद्भावः.

Dough, s. गुंडिका, जलसंसृष्टाः सक्तवः.

Doughty, a. शूर, वीर; See **Brave.**

Dour, a. दुर्दम, प्रतीप, कठिन.

Douse, v. t. जले निमस्ज् c. (मज्जयति). 2 निर्वा c. (वापयति).

Dove, s. कपोतः, पारावतः, कलरवः; 'female d.' कपोतिका; 'd.-cot or house' कपोतपालिका, विटंकः-कं; 'd. tail' काष्ठसंधिः, दारुसीवनं.

Dowager, s. विधवा, गतभर्तृका.

Dowdy, s. विस्रपिणी; दुर्वसना.

Dower, Dowry, s. शुल्कं, यौतकं, युतकं, वाहनिकं; स्त्रीधनं. -ed, a. यौतकवती, शुल्किनी. -less, a. यौतक-शुल्क-हीन.

Dowlas, s. स्थूलवस्त्रं, स्थूलपटं.

Down, s. कोमलरोमन् n. 2 तूलं, कोमलपक्षः; 'd. of goose' हंसतूलं; तृणलोमन् n. (of plants). 3 निर्वनपर्वतः. 4 निम्नं, निम्नप्रदेशः; the road having ups and d.s' नतोन्नतभूमिभागो मार्गः; 'ups and d.s' पातोत्पाताः; 'there are ups and d.s in our condition (in life) as in the course of the wheel' नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण (Me. 112). -prep. अधः, अधस्तात् (with gen.); gen. ex. by अनु in comp.; 'd. the current' अनुस्रोतं; 'd. to' यावत् (with acc.), पर्यंतं in comp.; 'd. to the present day' अद्य यावत्. -adv. अधः, अधस्तात्, नीचैः, नीचे; gen. ex. by अव-नि-अधः pr. to roots, 'bent d' अवनत, नीचैः प्रणत; 'to come d.' अव-नि-पत् 1 P; 'd. with the tyrant' निपात्यतां-उच्छेद्यतां-असौ प्रजापीडकः; 'd. cast' अधोमुख (खी f.), अवनतदृष्टि, विषण्ण, अधोदृष्टि, दीनवदन, म्लान, खिन्न; 'd.-fall' विनि-अप-पातः, विनाशः, क्षयः, उच्छेदः, विध्वंसः, लयः; 'd.-hearted' खिन्न-दीन-चेतस्, म्लान, विषण्ण; 'd-hill' प्रवणभूमि f., उपत्यका; 'd. lying' प्रासप्रसवकाला; (s.) शयनसमयः; 'd.-right' अवक्र, अकुटिल, स्पष्ट, सुव्यक्त, असंदिग्ध, प्रत्यक्ष; (adv.) अवक्रं, अकुटिलं, सरलं, अशेषतः, व्यक्तं, प्रत्यक्षं, सुस्पष्ट, भिन्नार्थं, सर्वतः, साकल्येन, सु-अति pr. -ward, a. प्रवण, पतनशील, अधस्तन (नी f.), अधोगामिन्, पतयालु, पातुक. -adv (downwards) अव pr., अधः, अवाक्, अधस्तात्. -y, a. मृदुलोमवत्. 2 मृदु, कोमल, सुकुमार, सुखस्पर्श.

Dowse, s. चपेटिका, तलप्रहारः. चपेटाघातः. -v. t. **Dip,** q. v.

Doxology, s. ईश-स्तुति f -स्तवनं.

Doyne, s. गुरुजनः, ज्येष्ठः, श्रेष्ठः, नेतृ m., धुरीणः.

Doze, v. i. निद्रा 2 P, स्वप् 2 P. -ing, -y, a. निद्रालस, निद्राशील.

Dozen, a., s. द्वादशन्, द्वादशसंख्याक.

Drab, a. कपिश, कपिल. -s. कपिशवस्त्रं. 2 कुलटा, बंधकी, व्यभिचारिणी, पुंश्चली.

Drabble, v. t. पंकेन लिप् 6 P or दिह् 2 U.

Draff, s. उच्छिष्टं, शेषं, भुक्तावशेषं, मलं, किट्टं. -ish, -y, a. मलिन, असार, फल्गु.

Draft, v. t. लिख् 6 P. -s. See **Draught** 2, 3, 4.

Drag, v. t. आकृष् 1 P, हृ 1 P: 'd. away, off' अप-अव-कृष्; 'd. out' निष्कृष्, निर्हृ, उत्पट् 10; 'd. s on his life' कथमपि कृच्छ्रेण-प्राणधारणां करोति, जीवितमतिवाहयति. -v. i. कृष् pass. 2 विलंब् 1 A, चिर (रा)यति (D.). -s. रथः, चक्रयानं, कोलिरथः. 2 आकर्षणी; 'd.-net' आकर्षकजालं-पाशः.

Draggle, v. i. पंके लुठ् c. pass. लोठ्यमानत्वात् मलिनीभू 1 P. -v. t. पंकेन कृष् (कर्षयति); 'd. tail' (a.) मलिनवसन, अपरिष्कृत.

Dragon, s. नागः, व्यालः, पन्नगः, सपक्षो नागः.

Dragoon, s. अश्वारोहः, सादिन् m.

Drain, *s.* निर्गमः, रेचनं; (for water) जलनिर्गमः, परी(रि)वाहः, प्रणालः-ली, प्रणालिका, जलोच्छ्वासः. -*v. t.* (क्रमशः) निर्गम् c. (गमयति), अपवह् c., निःसृ c., स्रु c. 2 शुष् c., आ-पा 1 P, क्षै c. (क्षपयति), रिच् c., रिक्तीकृ 8 U.

Drake, *s.* हंसः, कादंबः, कलहंसः.

Dram, *s.* अल्पभागः, मात्रा. 2 सुरा, वारुणी, मदिरा.

Drama, *s.* नाटकं; ' science of d. ' नाट्यं -**Dramatic,-al,** *a.* नाटकीय, नाटकविषय -**ally,** *adv.* नाटकरूपेण, प्रयोगतः. -**Dramatist,** *s.* नाटकानां प्रणेतृ *m.*, नाटककारः.

Drap, *s.* वस्त्रं, वसनं, चेलः-लं; *See* **Cloth.** -**er,** *s.* वस्त्र-पट-विक्रयिन् *m.* -**ery,** *s.* वस्त्रव्यवहारः. 2 वस्त्रं, पटः, वासस् *n.* 3 प्रच्छदपटः, परिच्छदः.

Drastic. *a.* अमोघ, बलवत्, प्रभविष्णु, अनतिक्रमणीय.

Draught, *s.* पानं; ' a d. of water ' गंडूषमात्रं जलं. 2 संग्रहः, सारः. 3 आलेखनं, चित्रारंभः, पांडुलेख्यं. 4 चित्रं, आलेख्यं, प्रतिमा-मानं. 5 परि(री)वाहः, जलनिर्गमः, जलोच्छ्वासः, प्रणालः-ली. 6 आकर्षणं; ' a d. horse ' रथ्यः, शाकट., शाकटीनः; ' d. board ' अष्टापदं, शारिफलं; अष्टापदक्रीडा, शारिक्रीडा; ' a piece at d. ' शा(सा)रिः, नयः, शा(सा)रः; जतुपुत्रकः; ' moving a piece at d ' परि(री)णायः. -**Draughtsman,** *s.* लेखकः, चित्रकरः.

Draw, *v. t.* कृष् 1 P, आ-समा-कृष्, वह् 1 P, नी 1 P; ' a carriage d. n by horses ' अश्वोढः रथः. 2 निष्कृष्, संहृ 1 P, (प्रजाभ्यो धनं संहरति), निर्हृ 2 U. 3 आ-अभिलिख् 6 P, वर्ण् 10. 4 (Water) उद्-अंच् 1 U, पर्युदंच्. 5 स्रु c., मोक्ष् 10. 6 समाकृष्, लुभ् c., ' d. n by merits ' गुणलुब्ध. 7 अनुनी 1 P. आराध् c. 8 लभ् 1 A, ग्रह् 9 P, आदा 3 A; ' the day is fast d. ing to a close ' परिणतप्रायमहः; ' d. curtains ' जवनिकां संवृ 5 U; ' d. a sword ' खड्गं कोषाद् निःसृ c. or आकृष्; ' d. in air ' प्राण् 2 P, श्वस् 2 P; ' d. the breast ' नि-पा 1 P, धे 1 P. -*v. i.* कृष्-आकृष्-pass. संकोचं-इ-या 2 P. 3 पूयं-पाकं जन् c. (जनयति) or उत्पद् c. -**away,** अपकृष्, अपनी, अपहृ. -**back,** प्रत्याहृ, प्रतिसंहृ, प्रत्यानी. 2 (*v. i.*) अपक्रम् 1 U, 4 P, अपसृ 1 P, अपया 2 P, परा-नि-वृत् 1 A, पलाय् 1 A. -**down,** उत्पद् c., जन् c, आवह् 1 P; ' you have d. n down ruin upon yourself with your own hands ' त्वया स्वहस्तेनांगाराः कर्षिताः (P. 1. 3). -**in,** संहृ, विकृष्, प्रत्याहृ; ' d. in the reins ' प्रगृह्णीतां रश्मयः. -**near,** प्रत्यासद् 1 P; उपसृप् 1 P, उपागम् 1 P, उपस्था 1 U; *See* **Approach;** (प्रत्यासीदति स्नानसमयः Ka. 47). -**off,** अप-वि-कृष्, अपहृ, अपनी; ' d. off the cloud ' निवार्यतां जलदः (Mr. 5.). 2 स्रु c., मुच् 6 P or c. (as liquids). 3 (*v. i.*) अपसृ 1 P; *See* **Drawback.** -**on,** आनी, आकृष्. 2 उत्पद् c., आवह् 1 P. 3 (*v. i.*) उपस्था, उपागम्, प्रत्यासद्. -**out,** निष्कृष्, निर्हृ, सं-हृ, निर्हृ. 2 तन् 8 U, विस्तॄ c., दीर्घीकृ 8 U. विततीकृ. 3 निर्गम् c. (गमयति), उद्-भू c. 4 (Army) व्यूहेन रच् 10, सैन्यं व्यूह् 1 U. -**together,** समाकृष्, संग्रह्, समानी. -**up,** उत्कृष्, उद्हृ-धृ 1 P, उत्तुल् 10. 2 लिख् 6 P, विरच् 10 निबंध् 9 P. 3 उन्नम् c. (नमयति); ' the goat drew himself up ' अज उत्तस्थौ, शनैर्वपुरुदनमयत्. -**Drawback,** *s.* प्रत्यूहः, अंतरायः. 2 हानि *f.*, अपचयः, अपायः. 3 उद्धारः; ' d.-bridge ' जंगम-चल-सेतुः. -**er,** *s.* कर्षकः. 2 चलसमुद्गकः, संपुटः, निष्कर्षणी; 'd. s' जंघावारः. -**ing,** *s.* आकर्षणं. 2 चित्रं, आलेख्यं, प्रतिरूपं; चित्रफलकः, प्रतिमानं. 3 चित्रकर्मन् *n.*, चित्रविद्या; ' d. room ' दर्शनगृहं, सभाजनकोष्ठः.

Drawl, *v. i.* चिरेण-मंदं मंदं-वाक्यानि उच्चर् c. or उद्वाह् 1 P. -**ing,** *s.* मंदोच्चारणं.

Dray, -man, *See* **Cart,-man.**

Dread, *s.* भीति *f.*, त्रासः, भयं, साध्वसं. -*v. t.* भी 3 P, त्रस् 1, 4 P, उद्विज् 6 A, (with abl.). -**ed,** *a.* भयहेतुः, त्रासस्थानं. -*a.*,-**ful,** *a.* दारुण, भयप्रद, भीम, भयंकर (री *f.*), त्रासावह, भीषण, भयानक, घोर, उग्र, भैरव (वी *f.*), रौद्र (द्री *f.*). -**fully,** *adv.* दारुणं, उग्रं, भीमं. -**less,** *a* निर्भय, त्रासहीन. -**naught,** *s.* युद्धनौका.

Dream, *s.* स्वप्नः, स्वापः, स्वप्नदर्शनं. 2 स्वप्नसृष्टि *f.*, मिथ्यावासना, असंभवकल्पना, आभासः, वृथावासना; ' bad d. ' दुःस्वप्नः; ' speak in a d.' उत्स्वप्नायते (D.). -*v. t.* स्वप्ने दृश् 1 P. -*v. i.* स्वप्नं दृश्, स्वप्नायते (D.). 2 चिंत् 10, भू c., मनसा कल्प् c., चित्ते आकल् 10 (कलयति). 3 वृथावासनां कृ 8 U, असंभवकल्पनां कृ. -**er,** *s.* स्वप्नदर्शिन् *m.* 2 दुर्वासनाकृत् *m.*, असंभवकल्पनाकृत् *m.* 3 उन्मत्तः. -**y,** *a.* स्वप्नोपम, स्वप्नवत् *ind.*; असार.

Dreary, *a.* घोर, निर्जन, शून्य, जीर्ण. 2 निरानंद, दुरालोक, दुर्दर्शन, निष्प्रभ. -**ness,** *s.* निर्जनत्वं, घोरता, शून्यत्वं.

Dredge, *v. t.* आकृष् 1 P. -*s.* आकर्षणी.

Dregs, *s.* खलं, मलः-लं, उच्छिष्टं, शेषं, किट्टं, अवकरः, संकरः, असारः; ' he belongs to the d. of society ' नीच-अधम-तमोर्थ पुरुषः. -**Dreggist,** *a.* मलिन, समल.

Drench, *v. t.* क्लिद् c., मोक्ष् 1 P, सिच् 6 P, जलेन क्लृ c. or स्ना c. (स्ना-स्न-पयति); 'd. ed with sweat' स्वेदसलिलस्नात. **-s.** पानं, पेयं.

Dress, *s.* वेशः-षः, नेपथ्यं, वस्त्रं, परिच्छदः, वाससू *n.*, वसनं, परिधानं. **2** आकल्पः, परिकर्मन् *n.*, आभरणं, प्रसाधनं, भूषणं, अलंकारः, संस्कारः, परिष्कारः, मंडनविधिः. **-v. t.** प्रसाध् c., अलंकृ 8 U, परिष्कृ, मंड् 10, भूष् 10; प्रा-वृ 5 U, वस्त्रेण आच्छद् 10 or परिवेष्ट् c., संव्ये 1 P, वस्त्रं परिधा c. (धापयति). **2** (Oneself) वस् 2 A, वस्त्रं परिधा 3 U. **3** उपक्लृप् c., संस्कृ, विधा 3 U, सज्जीकृ; 'd. food' (अन्नं) पच् 1 P, श्रा c. (श्रपयति), संस्कृ, श्री 9 U, सिद्धीकृ; 'd. hair' केशान् रच् 10 or विन्यस् 4 P; 'd. leather' चर्म परिष्कृ; 'd. wounds' क्षतं निर्णिज् 3 U or प्रक्षल् 10. **-ed,** *a.* परिच्छन्न, वस्त्रवेष्टित, सवेश, संवीत, प्रावृत, प्रसाधित, मंडित,भूषित, अलंकृत, सवासस्, वस्त्रान्वित, कृतनेपथ्य, कृतपरिकर्मन्, रचितवेषआकल्प; 'well d.' सुवेश, 'd. as' ex. by वेश-वासस् in comp.; 'd. as a sage' मुनिवेशः, मुनिवेषधारी; 'd. in black' नीलांबर. **2** पक्व, सिद्ध, संस्कृत, श्राण, श्रपित, शृत; 'half d.' आपक्व. **3** निर्णिक्त. **-er,** *s.* प्रसाधकः, आच्छादकः, आकल्पकः. **2** अन्नफलकः. **-ing,** *s.* वस्त्रपरिधानं, नेपथ्यविधानंअंगसंस्कारः, परिकर्मन् *n.* **2** पाकनिष्पत्ति *f.*, अन्नसंस्कारः, पाकसिद्धि *f.* **3** विलेपः-पनं, उपनाहः; 'd. room' नेपथ्यं, प्रसाधनागारं, वस्त्रपरिधानस्थानं.

Drib, *v. t.* अवच्छिद् 7 P, उद्धृ 1 P; अन्यायेन स्वायत्तीकृ or आत्मसात्कृ 8 U.

Dribble, *v. i.* कणशः स्यंद् 1 A, बिंदुक्रमेण पत् 1 P, शनैः क्षर् 1 P or स्रु 1 P or गल् 1 P. **-v. t.** कणशः स्रु c. or गल् c. **-Dribblet,** *s.* कणः, लवः, लेशः, कणिका, अल्पभागः, 'in d. s' बिंदुक्रमेण; कणशः, अल्पाल्पं.

Drift, *s.* भावः, तात्पर्यं, आशयः, अभिप्रायः, उद्देशः, प्रवृत्ति *f.*, आकांक्षा. **2** वेगः, रयः. **3** राशिः, संचयः, पुंजः, निकरः; 'd. of snow' हिमसंहति *f.*, हिमानी. **4** संपातः, वर्षः. **-v. i.** प्रवह् 1 P, जलस्रोतसा नी-वह् pass. **2** विप्लु 1 A, (विप्लवेतेह नौरिव H. 3) **3** वायुवेगेन पुंजीभू 1 P. **-v. t.** प्रवह् c., प्रेर् c. प्रचुद् 10, प्रणुद् 6 P or c. **2** संपत् c., राशीकृ 8 U, संहन् 2 P, पुंजीकृ.

Drill, *s.* वेधनी-निका, आ-स्फोटनी. **2** व्यायामः, अस्त्रशिक्षा, शस्त्राभ्यासः. **-v. t.** व्यध् 4 P, छिद्र् 10, समुत्कृ 6 P. **2** युद्धविद्यां शिक्ष् c.; शस्त्राभ्यासं कृ c.; रणशिक्षां दा 3 U.

Drink, *v. t.* पा 1 P; 'd. up' आचम् 1 P आपा, क्षुच् c. **-s.** पानं, पानीयं, पयस् *n.*, पेयं. **2** सुरा, मद्यं. **-v. i.** जलं पा or सेव् 1 A; 'd. together' सं-पा, सपीतिं कृ 8 U; 'd. (to) the health of' स्वास्थ्याय or शुभं भूयादिति प्रार्थनापूर्वकं पा. **-er,** *s.* पातृ *m.*, पायिन् *m.*, पानरतः, पानासक्तः. **-ing,** *s.* पानं, आचमनं, पीति *f.*; 'd. vessel' पानपात्रं-भाजनं, चषकः, सरकः; 'd. together' सपीति *f.*, तुल्यपानं. **-Drunk, Drunken,** *a.* मत्त, क्षीब, समद, मदोन्मत्त, उपोढमद, मदोद्धत; 'to be d.' मद् 4 P; 'to make d.' मद् c. **2** सिक्त, क्लिन्न. **-ard,** *s.* पानरतः, पानासक्तः, पानशौंडः, मधुपः, मद्यपः. **-enness,** *s.* मदः, मत्तता, क्षीबता, उन्मादः.

Drip, *v. i.* कणशः-बिंदुक्रमेण-क्षर्-गल्-स्रु 1 P or स्यंद् 1 A; 'd. ing garment' जलनिस्यंदि वस्त्रं. **-v. t.** कणशः स्रु c. or गल् c. **-s.** पटलप्रांतः-तं, वलीकः-कं, नीध्रं. **-ping,** *s.* क्षरणं, स्रवणं, गलनं, स्यंदनं, निस्यंदः. **2** मांसवसा, मांसस्नेहः-रसः; 'd. pan' रसधारिणी.

Drive, *v. t.* चर्-ल् c., नुद् 6 P or c., प्रणुद्; प्रेर् c.; (fig.) प्रवृत् c., प्रोत्सह् c., उत्तिज् c., उद्युज् 10. **2** वह् c., कृष् 1 P, नी 1 P, प्र-चुद् 10 (fig. also); 'd. n to do this rash act' चापलाय प्रचोदितः (R. 1. 9); 'd. a nail' कीलं प्रविश् c. **-v. i.** रथेन गम्-चल्-चर् 1 P. **2** सं-अप-वह् pass., चल् c. pass., नुद्-कृष्-नी pass.; 'a sharp d. ing shower' अविरलवारिधारासंपातः (U. 6) पटुधारासारः (V. 4). **3** आपत् 1 P, अभिद्रु 1 P, संघट्ट् 1 A. **-s.** रथेन संचरणं or विहारः. **-at,** उद्दिश् 6 P, अभि-प्र-इ 2 P; अधिकृत्य-उद्दिश्य-वद् 1 P; 'what are you d. ing at' किमुद्दिश्य भवान्भाषते. **-away, -off,** निर्-अप्-अस् 4 U, अपवह् c, निर्-अप-सृ c., निरा अपा-कृ 8 U, अपानुद् निर्धू 5, 9 U; हृ 1 P, अप-परि-हृ, अप-ऊह् 1 U. **-out,** निर्वस् c., निष्कस् c., बहिष्कृ, निर्गम् c., विवस् c., नि-अप-सृ c. **-er,** *s.* प्रेरकः, वाहकः. **2** यंतृ *m.*, रथवाहकः,प्राजितृ *m.*, सूतः, नियंतृ *m.*, क्षत्तृ *m.*, सारथिः, सव्येष्ट *m.*, दाक्षिणस्थः. **-ing,** *s.* प्रेरणं, प्रचोदनं, निराकरणं &c. **-Drove,** *s.* कदंबकं, यूथं, गणः, कुलं, संघः. **2** पशुसमूहः.

Drivel, *s.* लाला, सृणि(णी)का, स्यंदिनी, द्राविका. **-v. i.** लालां पत् c. or निःसृ c. or स्रु c. **2** बुद्धिविकल *a.* भू 1 P, जडीभू, हतज्ञान *a.* भू. **-ler,** *s.* लालास्रावकः. **2** मूर्खः, बालिशः, जडः, मूढः, हतज्ञानः.

Drizzle, *v. i.* मंदं मंदं वृष् 1 P, शीकरायते (D.). **-v. t.** शीकरं वृष्. **-ing,** *s.* शीकर-

वर्षः-पातः (a d. shower). **-Drizzly,** *a.* शीकरयुक्त, तुषारविशिष्ट.

Droll, *s.* भंडः, वैहासिकः, विदूषकः. -*a.* हासकर (री *f.*), उपहास्य, विनोदिन्, असंबद्ध. -*v. i.* परिहासं उत्पद् c. **-ery,** *s.* परिहासः, हास्यं, विहासः, विनोदः, नर्मालापः.

Dromedary, *s.* क्रमेलः-लकः, एककाकुद् *m.*

Drone, *s.* (**dronish**) अलसः, निरुद्योगः; आलस्यशीलः, तंद्रालुः, निरुत्साहः.

Droop, *v. t.* अवनम् c. (नमयति); नम्रीकृ 8 U; *See* **Bend.** -*v. i.* अव-वि-सद् 1 P, म्लै 1 P, ग्लै 1 P, स्रंस् 1 A, गल् 1 P, क्लम् 1, 4 P; ध्वंस् 1 A, क्षि-मुच्-pass., शिथिलीभू 1 P, अव-अा-नम् 1 P. 'let not your spirits d. (flag) 'मा भवानंगानि मुंचतु (V. 2); 'I slept with d. ing limbs' श्लथैरवयवैरशायिषि (D. K. II. 2); 'the vine is d. ing with its load' फलभारानमिता द्राक्षालता; 'the whole frame d. s down' स्रंसते देहबंधः (U. 3) **-ing,** *a.* अवसन्न, म्लान, क्लांत, स्रस्त, शिथिल, स्रंसिन्. **2** आ-अव-नत, आवर्जित, नम्रीभूत, नमित.

Drop, *s.* बिंदु, *m* , पृषत् *n.* लवः, विप्रुष् *f.*, पृषतः, कणिका, कणः, शीकरः; 'd. by d.' बिंदुक्रमेण, कणशः; 'small d. s make a pool' जलबिंदुनिपातेन क्रमशः पूर्यते घटः. (H. 2). **2** कर्णावतंसः; लोलकः, कुंडलं. -*v. t.* कणशः स्रु c. or पत् c. or स्यंद् c. 'd. ing rut' मदं क्षरंतः, मदनिस्यंदिनः (गजाः) 'd ing. nectar' अमृतस्रुत्, सुधास्यंदिन्. **2** अव-, नि पत् c., स्रंस् c., भ्रंश् c., च्यु c, मुच् 6 P, विसृज् 6 P, निविश् c. **3** सं-हृ 1 P, अपास् 4 P, त्यज् 1 P, निवृत् 1 A, (with abl.); 'I shall d. congratulatory lines regarding you in my letters' मदीयेषु लेखेषु त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि (M. 5). 'let this matter (story) be d. ed' संह्रियतामियं कथा (Ka. 169). -*v. i.* स्रु 1 P, च्युत-श्चुत् 1 P, क्षर् 1 P, गल् 1 P, स्यंद् 1 A **2** स्रंस्-च्यु- 1 A, भ्रंश् 1 A, 4 P; नि-,पत्, 'd. ing on his knees' जानुभ्यामवनौ गत्वा,क्षितितलनिहितजानुः. **3** नि-,अव-, पत् 1 P, अवसद् 1 P, मूर्छ् 1 P, *See* **Droop;** 'I feel ready to d.' अवसन्नप्रायाणि मे गात्राणि, सीदंति मे अंगानि. **4** (in) सहसा-अतर्कितं-गम् 1 P or आगम.

Dropsy, *s.* (generally) शोफ , शोथः. **2** जलोदरं, जठरामयः, उदरी ; 'dropsied honour' केवलं स्थूलः-महाप्रमाणः-मानः.

Dross, *s.* मंडूरं, सिंहाणं (नं), लोहमलं, सिंघाणं. **2** मलं, खलं, किट्टं; *See* **Dregs. -y,** *a.* समल.

Drought, *s.* अवग्र(ग्रा)हः, अनावृष्टि *f.*, अवर्षणं, जलशोषः, वृष्टिविघातः. वर्षनिरोधः. **-y,** *a.* जलशून्य, शुष्क, निवग्रह, निर्वृष्टि.

Drove, *s. See* under **Drive.**

Drown, *v. t.* मस्ज् c.; आ सं-परि प्लु c. **2** जले निमस्ज् c., (मज्जयति) or प्रविश् c. **3** जलमज्जनेन व्यापद् c. or मृ c. **4** तिरोधा 3 U, तिरयति (D.) 'd. s my voice with his cries' केकाभिस्तिरयति मे वचनं (Mal. 9) -*v. i.*, 'to be d. ed' नि-मस्ज् 6 P, निमज्जनेन मृ 6 A, or नश् 4 P or व्यापद् 4 A;' d. ed in the sea' पयोराशौ निमग्न; 'd. ed in reflection' चिंतामग्न. **-ing,** *s.* मज्जनं, आप्लावः, प्लावनं.

Drowse, *v. i.* नि-द्रा 2 P, स्वप् 2 P, स्वप् desid. (सुषुप्सति). **-Drowsy,** *a.* निद्रालु, तंद्रिल, निद्रालस, निद्राशील, अलस. **-ness,** *s.* तंद्रा, निद्रालुत्वं, आलस्यं, निद्रा, निद्राशीलत्वं, शयालुता.

Drub, *v. t.* वेत्रेण तड् 10 or प्र-हृ 1 P.

Drudge, *v. i.* अविरतं-अतिक्लेशेन-आयस् 1, 4 P or परिश्रमं कृ 8 U, शरीरायासेन व्रातं कृ. -*s.* व्रातीनः, अविरतायासिन् *m.*, अतिक्लेशेन निकृष्टकर्मकारिन् *m.*, हीनवृत्ति *m.* **-ry,** *s.* अविरतायासः, शरीरक्लेशः, नित्यश्रमः, नित्यक्लेशः, निकृष्टकर्माभियोगः, व्रातं.

Drug, *s.* औषधं, भेषजं, अगदः, भैषज्यं, जायु *m.* -*v. t.* औषधादिना मिश्र् 10 or संसृज् 6 P. **-Druggist,** *s.* औषधविक्रयिन् *m.*, भेषजकारः.

Drugget, *s.* स्थूलपटः, स्थूलशाटकः, वराशि *m.*

Drum, *s.* पटहः *m.*, दुंदुभि *m.* डिंडिमः, भेरी, आनकः. **2** कर्णोदरं, कर्णदुंदुभि *m.* -*v. i.* पटहं तड् 10 **2** ध्वंज् 1 A. **-mer,** *s.* पटहताडकः. **-Drumstick,** *s.* कोणः, शारिका.

Dry, (up) *v. i.* शुष् 4 P, शोषं या 2 P or गम् 1 P, आश्यै 1 A, नीरसीभू 1 P, शुष्कीभू. -*v. t.* शुष् c., शोषं नी 1 P, आश्यै c., रसं अपनी or हृ 1 P, शुष्कीकृ 8 U 'she dried rice in the sun' तंदुलान्सूर्याते दत्तवती. **2** (up) आचम् 1 P, (आचामति स्वेदलवान् मुखे ते R. XIII. 20); उच्छुष् c., आ-नि-पा 1 P. -*a.* शुष्क, निर्जल, नीरस, अक्लिन्न, वान. **2** असार, निःसार, निःसत्त्व, अरस, नीरस, फल्गु, विरस, तुच्छ. **3** उदकार्थिन्, तृषित, तृषार्त; 'd. soil' मरु *m.*, मरुस्थलं-ली; 'd. ground' स्थलं; 'd.-eyed' निरश्रुनयन. 'd. nurse' शिशुपालिका, अंकपाली; 'd. f.' शुष्कचरण *a.* **-er,** *s.* शोषकः-णः 'ing, *s.* शोषः, शोषणं, शुष्कीकरणं. -ly, *adv.* शुष्कं,नीरसं अरसिकतया. **-ness,** *s.* शोषः, शुष्कता, निर्जलत्वं, अरसिकत्वं.

Dryad, *s.* वनदेवता.

Dual, *a.* द्विसंख्य, द्विवाचक, द्विक; 'the d. number' द्विवचनं. **-ity,** *s.* द्वैतं, द्वित्वं, द्वैधं.
Dub, *v. t.* नवपदे नियुज् 7 A, 10, नवपदवीं दा 3 U or आरुह् c. (रोपयति).
Dubious, *a.* अस्पष्ट, अव्यक्त, संदिग्धार्थ. **2** संदिग्ध, अनिश्चित; *See* **Doubtful. -ly,** *adv.* ससंशयं, साशंकं, अस्पष्टं, अव्यक्तं.
Duck, *s.* कलहंसः, कादंबः, चक्रवाकः, हंसः, प्लवः, वरटः. **2** तिर्यक्क्षिप्तः प्रस्तरः **3** दयितः-ता, प्रियः-या, वत्स -त्सा. *-v. i.* मस्ज् 6 P, अवगाह् 1 A; मस्तकं नम् c. *-v. t.* जले अवगाह् c. or आप्लु c. or मस्ज् c. (मज्जयति). **-er,** *s.* आप्लावकः, मंक्त *m.* **-ing,** *s.* मज्जनं, अवगाहः, आप्लावनं. **-ling,** *s.* हंस-शावकः-शिशुः.
Duct, *s.* प्रणालः-ली, मार्गः, संक्रमः, कुल्या. **2** शिरा, नाडि-डी *f.*, धमनी.
Ductile, *a.* विनेय, विधेय, वश्य. **2** आनम्य, मृदु, कोमल, उद्वर्तनयोग्य. **-Ductility,** *s.* वश्यता; आनम्यता; सुखोद्वर्तनीयता
Dude, *s. See* **Fop.**
Dudgeon, *s.* अमर्षः, कोपः; *See* **Anger. 2** असिपुत्रिका, कृपाणिका.
Due, *a.* देय, दातव्य, परिशोध्य; ex. by pot. pass. part., or अर्ह् 1 P; 'respect is d. to our elders' पूज्या हि गुरवः; 'the debt d.' परिशोध्यं ऋणं. **2** अनुरूप, युक्त, उचित, योग्य, यथार्ह, यथा in comp.; 'in d. time' समये, यथासमयं; यथाविधि, &c. **3** (Owing to) ex. by कारणं, हेतुः; 'your failure is d. to your carelessness alone' प्रमाद एव तवासिद्धेः कारणं-हेतुः, प्रमादात् तवासिद्धिः प्रभूत -*s.* देयं, परिशोध्यं, ऋणं. **2** प्राप्यं, ग्राह्य, प्राप्तव्यं, योग्यांशः. **3** कर्तव्यं, अवश्यं कार्यं. **4** करः, शुल्कः-ल्कं, राजग्राह्यो भागः, राजस्वं. **5** अधिकारः. **-Duly,** *adv.* यथातथं, औचित्येन, यथार्हं, उचितं, सम्यक्. **2** यथासमयं, समये, यथावसरं.
Duel, *s.* द्वंद्वं, द्वंद्वयुद्धं, मल्लयुद्धं, नियुद्धं, बाहुयुद्धं. *-v. i.* द्वंद्वयुद्धं कृ 8 U, द्वंद्वं कृ. **-ler, -list,** *s.* द्वंद्व-मल्ल-योद्धृ *m.*, द्वंद्वकृत् *m*
Duffer, *See* **Dunce. 2** *See* **Pedlar.**
Dug, *s.* स्तनः, पयोधरः.
Dulcet, *a.* सुरस, स्वादु, मधुर, मिष्ट; 'd. to the ear' सुखश्रव, सुस्वर, श्रुतिमनोहर. **-Dulcify,** *v. t.* मधुरीकृ 8 U, स्वादूकृ.
Dulcimer, *s.* वल्लकी, विपंचिका.
Dull, *a.* मंद, मूढ, जड, मंद-स्थूल बुद्धि-मति; 'd.-witted' दुर्मति, जडमति, मंदधी **2** निष्प्रभ, विषण्ण, निस्तेजस्, निरुत्साह, क्लांत, म्लान, मंदच्छाय, मलिन, मंदद्युति. **3** अतीक्ष्ण, धाराहीन, अतेजस्, कुंठ. **4** अरस, मंथर, जड, मंदगति, मंद अक्षुण्ण, शीतक, तुंदपरिमृज. **5** स्थूल, घन. **6** अरस, अरसिक. **7** कष्टकर (री *f.*), विषम, निरानंद; 'd. of hearing' विकलकर्ण; 'a d. day' दुर्दिनं, तमोवृतं नभः. *-v. t.* जडीकृ 8 U, मुह् c., कुद् 10, अतीक्ष्णीकृ, घनीकृ, निष्प्रभीकृ, तेजो ह्र 1 P, वि-श्रद् c., म्लानीकृ, उत्साहं भंज् 7 P. **-ness,** *s.* मांद्यं, जाड्यं, मूढता; अतीक्ष्णता, आलस्यं, तेजोमांद्यं, निष्प्रभता, अतेजस् *n.*, &c.
Dumb, *a.* मूक, जड, जडवाच्, वाग्रहित, वाक्शक्तिहीन, अनालप, अवाच्. **-ly,** *adv.* मूकवत्, निःशब्दं; तूष्णीं, वाग्व्यतिरेकेण. **-ness,** *s.* मूकता, वाक्स्तंभः, जाड्यं, वाग्राहित्यं.
Dumpish, *a* विषण्ण, दीन, उद्विग्न.
Dumps, *s.* विषादः, उद्वेगः, म्लानि *f.*
Dumpy, *a.* ह्रस्वस्थूल.
Dun, *a.* कपिश, श्याव-म, पिंगल, कृष्ण. *-s.* सनिर्बंधं ऋणप्रार्थना.
Dunce, *s.* स्थूलबुद्धिः, दुर्मेधस् *m.*, अज्ञः, अनभिज्ञः, मूढः, मूढमतिः, जडः, जडधीः.
Dune, *s.* सैकतचयः, वालुकानिचयः.
Dung, *s.* पुरीषं, विष्ठा, शकृत् *n.*, शमलं, विष् *f.*, अप(व)स्करः, गूथं, वर्चस्कः-स्कं, उच्चारः, 'd. hill' शकृन्निचयः, अवकरनिकरः, (*a.*) हीनजाति, अधम, नीच. *-v. t.* पुरीषेण लिप् 6 P or अंज् 7 P.
Dungeon, *s.* कारा, कारागृहं-वेश्मन् *n.*, बंधनागारं, अंधकूपः.
Dupe, *v. t.* वंच् 10; प्रलुभ् c.; *See* **Cheat.** *-s.* सुखप्रतार्यः, सुखेन वंचनीयः.
Duplex, *a.* द्विगुण.
Duplicate, *a.* द्विगुण; 'a d. copy' प्रतिलिपि *f.*; प्रतिरूपं. *-v. t.* द्विगुणीकृ 8 U, पुटीकृ, पुटयति (D). **-ion,** *s.* द्विगुणीकरणं, पुटीकरणं. **-ure,** *s.* पुटः-टं, भंगः; व्यावर्तनं
Duplicity, *s.* कपटं, छलं, माया; द्वैधीभावः; *See* **Fraud.**
Durable, *a.* स्थायिन्, चिरस्थायिन्, दीर्घकाल, अविनाशिन्, स्थिर, ध्रुव, अक्षय, अनपाय. **-Durably,** *adv.* स्थिरं, ध्रुवं, अनपायेन. **-Durability,** *s.* स्थिरता, अक्षयता, चिरस्थायित्वं.
Durance, *s.* आसेधः, निरोधः, बंधनं, कारानिरोधः.
Duration, *s.* स्थायित्वं, अवस्थिति *f.*, स्थिति *f.* **2** ध्रुवता, स्थिरता, अविरामः, अविच्छेदः, सातत्यं. **3** परिमाणं; 'of long d.' दीर्घस्थायिन्, स्थायिन्; 'of short d.' अस्थायिन्, क्षणभंगुर, क्षणिक.
During, *prep.* यावत्, मध्ये, अंतरे in comp.; ex. by loc., or loc. abs.; 'd. youth' यौवनदशायां; 'd. Das'aratha's reign' दशरथे महीं शासति; 'd. life' यावज्जीवं-वन; oft. by आ with abl.

Dusk, *s.* संध्या, प्रदोषः, संध्याकालः-समयः; 'time of d.' सायंतनः समयः, संध्याकालः, सायंकालः. *-a.*, **-y, -ish,** *a.* ईषत्तामस (सी *f.*), ईषत्तिमिरावृत, ईषत्कृष्ण, सतमस्कल्प, आकृष्ण, आनील. **-ily,** *adv.* अस्पष्टं, ईषत्तमसा. **-iness,** *s.* ईषदंधकारः, ईषत्तिमिरं.

Dust, *s.* धूलि-ली *f.*, रजस् *n.*, रेणु *m.*, *f.*, पांशुः *m.*-सुः *m.*, क्षोदः, चूर्णं. **2** संकरः, अवकरः-स्करः, उच्छिष्टं; 'd. of flowers' परागः; 'fragrant d.' पिष्टातः, पटवासः; 'd. of gold' कांचनभूः; 'd. coloured' धूलिधूसर. *-v. t.* रेणुं अपमृज् 2 P, नीरजीकृ 8 U, निर्धूलीकृ; 'd. hole-bin' संकरनिचयस्थानं; 'd.-man' खलपूः, धूलिमार्जकः, रजोवाहकः. **-ed,** *a.* नीरजीकृत, हृतपांशु, संमृष्ट. **-er,** *s.* मार्जनपटः, नक्तकः, रेणुसंमार्जकः. **-y,** *a.* पांशुल, धूलिधूसर, रेणुदूषित-रूक्ष.

Duty, *s.* धर्मः, कर्तव्यं. **2** कर्मन् *n.*, कृत्यं, कार्यं, नियमः, व्रतं. **3** नियोगः, अधिकारः, पदं, आस्पदं; 'one who has done his d.' कृतकृत्यः, कृतिन् *m.*; 'morning duties' प्रातःकृत्यानि; 'having heavy d.' धुर्यः, धूर्वहः, धुरीणः. **4** करः, शुल्कः-ल्कं; तार्यं, तारिकं (for boats). **5** आदरः, भक्ति *f.*, मानः. **-Duteous, -Dutiful,** *a.* भक्त, आज्ञाधारक, अनुविधायिन्, आज्ञापालक, आदृत, धर्मज्ञ, भक्तिमत्, वश्य, ज्ञातधर्मन्; *See* **Obedient. -ly,** *adv.* भक्तवत्, भक्त्या. **-ness,** *s.* भक्ति *f.*, आज्ञानुवर्तनं, वश्यता, सेवा, शुश्रूषा, अनुरोधः.

Dux, *s.* अग्रणी *m.*, छात्रोत्तमः.

Dwarf, *s.* वामनः, खर्वः, ह्रस्वः, ह्रस्वकायः. *-v. t.* ह्रस् c., खर्वीकृ 8 U. **-ish,** *a.* खर्व, वामन, ह्रस्व, अतुंग, खर्वाकार, वामनमूर्ति.

Dwell, *v. i.* वस् 1 P, नि-प्रति-वस्, आ-अधि-वस् (with acc.), वृत् 1 A, स्था 1 P. **2** अध्यास् 2 A., आश्रि 1 U, निषेव् 1 A; 'd. upon' विस्तरेण वर्ण् 10; प्रपंचयति (D.), सविस्तरं निरूप् 10; 'd. abroad' प्रवस्; 'd. together' एकत्र-सं-वस्. **-er,** *s.* निवासिन्-वासिन्-वासकृत् *m.*, स्थ-वर्तिन् in comp. **-ing,** *s.* नि-आ-वासः, वसति *f.*, निलयः, आलयः, वसतिस्थानं, गृहं, आयतनं, आगारं, भवनं, आवसथः, ओकस् *n.*; *See* **House**; 'd. house or place' वासगृहं-स्थानं.

Dwindle, *v. i.* *See* **Decrease**; 'the number of members d ed down to four' सभासदां संख्या तथा क्षीणाभूद् यथा चत्वार एव अवशिष्टाः.

Dye, *s.* रंगः, वर्णः, रागः; 'red d.' लाक्षा. *-v. t.* रंज् 10, वर्ण् 10, कुंकुमादिना अञ्ज् 7 P. **-ed,** *a.* रक्त, रंजित, सराग, कषायित, वर्णित; 'd. red' अरुणित. **-er,** *s.* रंजकः, वस्त्ररागकृत् *m.*

Dyke, *See* **Dike.**

Dynasty, *s.* वंशः, कुलं, अन्वयः, आवलि-ली *f.*, श्रेणिः; 'of solar d.' सूर्यवंश्यः.

Dysentery, *s.* प्रवाहिका, अतिसारः, प्रस्कंदिका, आमातिसारः, संग्रहणी.

Dyspepsia, *s.* अजीर्णं-र्णि *f.*, मंदाग्निः, अन्नविकारः, अपाकः.

Dyspnœa, *s.* श्वासावरोधः, श्वासस्तंभः.

E.

Each, *a.* सर्व, सकल; gen. ex. by प्रति-अनु in comp., or by repetition of word; दिने दिने, प्रतिदिनं, &c.; 'all went away, e. to his own house' एकैकः स्वं स्वं गृहं निर्जगाम; 'e. one' एकैक *a.*, एकैकशः, पृथक् पृथक्; 'e. other' अन्योन्यं, इतरेतरं, परस्परं.

Eager, *a.* (Of persons) उत्सुक, लालस, लोलुप, अत्याकांक्षिन्, व्यग्र, सोत्कंठ, आसक्त, रत, सोत्साह. **2** गाढ, प्रबल, उत्कट, प्रचंड, सातिशय; तीव्र, तीक्ष्ण; oft. ex. by उत्तम् 4 P, (उत्ताम्यति मे हृदयं तद्दर्शनाय Ka.349). **-ly,** *adv.* सस्पृहं, सतृष्णं; सोत्कंठं, कुतूहलात्, अतिवांछया, उत्कटं. **-ness,** *s.* लालसा; औत्सुक्यं, उत्साहः, अतिस्पृहा-वांछा, उत्कटता, व्यग्रता, कुतूहलं, कौतुकं.

Eagle, *s.* गरुत्मत् *m.*, उत्क्रोशः; *See* **Garuda**; 'e. eyed' सूक्ष्मदृष्टि.

Ear, *s.* कर्णः, श्रोत्रं, श्रुति *f.*, श्रवणं, श्रवः, शब्दग्रहः, 'outer e.' श्रुतिमंडलं-वेष्टनं; 'lobe of e.' कर्णपालि *f.*; 'root of e.' कर्णमूलं, कर्णजाहं; 'tip of e.' श्रवणपालि-ली *f.*; 'having the e. s pricked' स्तब्धकर्ण; 'give e.' **attend to** q. v.; 'he has his lord's e.' स भर्तुर्विश्रंभस्थानं-विश्वासभूमिः; 'e.-ache' कर्णशूलः-लं; 'e.-drop' कर्णपूरः; 'e.-lap' कर्णपालिः, कर्णशष्कुली; 'e. pick' कर्णकंडूयनकः; 'e.-ring' कर्णावतंसः, कुंडलं; कर्णभूषणं, कर्णिका, उत्तंसः; 'e. shot' कर्ण-श्रवण-गोचरः-विषयः; 'be within e.-shot' श्रवणगोचरे तिष्ठ; 'e.-wax' कर्णमलं, पिंजूषः; 'e.-witness' श्रुतसाक्षिन् *m.*; 'e.-wig' कर्णकीटः-जलूका. **2** शीर्षकं; कणिशं, मंजरी.

Early, *a.* आद्य, प्रथम, पूर्व. **2** अचिर, सद्यस्क, प्रत्यग्र, अभिनव, नूतन. **3** अकाल, अपूर्णकाल, आकालिक (की *f.*), अनवसर-परिणत or पक्व. **4** प्रातःकालीन, पूर्वाह्णतन-प्रगेतन (नी *f.*). वि-प्र-भातीय, उषस्य, औषस (सी

f.), प्रभात-प्रातः in comp. *-adv.* प्रातर्, प्रत्युषसि, प्रत्यूषे; विभाते, प्रातःकाले, प्रभाते, व्युष्टे, प्रगे; 'e. in the morning' महति प्रत्यूषे; 'getting up e.' लघुलघूत्थित. **2** सद्यः, शीघ्रं, सत्वरं, आशु, सपदि. **3** पूर्वं, अग्रे, प्राक्. **-ness,** *s.* पूर्वत्वं, अग्रत्वं. **2** प्रत्यग्रता, अचिरत्वं. **3** अकालता, अकालपरिणति *f.* **4** सुप्रभातं. **5** क्षिप्रता, अविलंबः, शीघ्रता.

Earn, *v. t.* अर्ज् 10, उपार्ज्, उपादा 3 A, आप् 5 P; लभ् 1 A, निर्विश् 6 P; *See* **Get. 2** अर्ह् 1 P: 'e. livelihood' वृत्तिं क्लृप् c. or सं-पद् c. **-ings,** *s.* उपार्जितं, वेतनं, लभ्यांशः.

Earnest, *a.* उद्युक्त, कृतोद्यम; *See* **Eager;** 'e. desire' गाढाभिलाषः, अतिस्पृहा, कुतूहलं. **2** निविष्ट, एकाग्र, समाहित, आसक्त, एकतान, एकायन, एकसर्ग, एकाग्र्य, अनन्यासक्त, एकाग्रचित्त, अभिनिविष्ट, अनन्यविषय, उद्योगिन्; आसक्तचित्त, अनन्यवृत्ति, निविष्टमनस् (of persons). **3** अपरिहासशील. *-s.* अपरिहासः, अलाघवं; 'I am in e.' न परिहसामि, नायं परिहासस्य समयः; 'take in e.' परमार्थेन ग्रह् 9 P, (परिहासविजल्पितं वचः परमार्थेन न गृह्यतां S. 2). **2** सत्यंकारः, सत्याकृति *f.*, सत्यापनं-ना. **3** पूर्वभुक्ति *f.* **4** उपन्यासः, निक्षेपः, आधिः. **-ly,** 'in e.' *adv.* समाहित-निविष्ट-चेतसा, यत्नतः, सोद्योगं, एकाग्रमनसा, अभिनिवेशेन, उत्सुकं, सोत्साहं; 'e. desirous' अत्याभिलाषिन्, गाढाभिलाष. **2** अपरिहासेन, परमार्थतः, अलाघवं. **-ness,** *s.* एकाग्रता, उत्कटता, औत्सुक्यं, अभिनिवेशः, चित्तासक्ति *f.*, उत्साहः, अभियोगः, उद्योगः.

Earth, *s.* मही, पृथिवी, पृथ्वी, वसुधा, उर्वी, वसुंधरा, धरा, धरित्री, मेदिनी, वसुमती, धरणी, अवनि *f.*-नी, भूः, भूमि *f.*, क्षो(क्षौ)णि *f.*-णी, क्षिति *f.*, अचला, अनंता, रसा, विश्वंभरा, स्थिरा, काश्यपी, सर्वसहा, कु *f.*, इला, ज्या, गोत्रा, क्ष्मा, क्षमा, भूतधात्री, रत्नगर्भा, जगती. **2** मृद् *f.*, मृत्तिका. *-v. i.* भूमौ बिलं कृत्वा निवस् 1 P. *-v. t.* भूमौ निविश् c. or निधा 3 U or निक्षिप् 6 P; 'e.-born' भूमिज, महीज; 'e. ling' भूजंतु *m.*, मर्त्यः, पामरः; 'e.-quake' कंपः-चलन in comp. with (*s.*); क्ष्माचलितं, भूकंपः, &c.; 'e. worm' भूजंतु *m.*, नीचजनः, अधमः. **-en,** *a.* मृण्मय (यी *f.*), मार्तिक (की *f.*); 'e. ware' मृद्भांडं, कौलालकं, मार्तिकं. **-ly,** *a.* पार्थिव (वी *f.*), सांसारिक (की *f.*), ऐहिक (की *f.*), मर्त्य; नश्वर; विनाशधर्मन्; 'e.-minded' संसारासक्तचित्त; विषयोपभोगरत. **-y,** *a.* पार्थिव, भौम (मी *f.*), मार्तिक.

Ease, *s.* सुखं, सौख्यं, विश्रामः, निर्वृति *f.*, निरुद्वेगता, स्वास्थ्यं, स्वस्थता; 'I am at e.' लब्धं स्वास्थ्यं मया; अहं निर्वृतः, वीतचिंतः; 'this my soul is completely at e.' जातो ममायं विशदः प्रकामं अंतरात्मा (S. 4); 'at one's e.' यथाकामं, पर्याप्तं, यथेच्छं, प्रकामं, सुखेन, सुख in comp., अकुतोभयं, निर्वृत्या; 'sleeping at e.' सुखसुप्त. **2** सौकर्यं, अनायासः, सुकरत्वं, सुखं, लीला. *-v. t.* लघयति (D.), लघूकृ 8 U, प्र उप-शम् c. (शमयति), सां(शां)त्व् 10: ह्व 1 P, अपनी 1 P; 'e. from griefs, burden &c. &c.' दुःखात् &c. मुच् c., दुःखं-भारं-अपनी, उद्धृ, &c. **-Easy,** *a.* सुकर, अयत्नसाध्य, अनायास, सुखसाध्य. **2** सुबोध, सुगम, अविषम; अगहन; gen. ex. by सुख or सु in comp., अज्ञः सुखमाराध्यः; बालानां सुखबोधाय, &c.; 'e. of utterance' सुखोच्चार्य; 'e. style' सुगमा भाषासरणिः; 'e. to get' सुलभ, सुखलभ्य, &c.; 'e. in going' सुखचार; 'e. case' निःशल्योर्थः. **3** निर्वृत, सुस्थ, निश्चिंत, स्वस्थ, सुखिन्, निरुद्वेग, शांत, वीतचिंत, निर्वृतिमत्, विशद; 'e. circumstances' सुस्थिति *f.*, द्रव्यानुकूल्यं; 'heart, be not un-e.' हृदय मा उत्ताम्य (S. 1). **4** अनुकूल, अनुराधिन्, अनुविधायिन्. **-ly,** *adv.* अनायासेन, सुखं, सुखेन, अयत्नेन, लीलया, अश्रमेण, सुकरं, अक्लेशं, सौकर्येण; सु or सुख in comp. **2** निरुद्वेगं, निश्चिंतं, स्वास्थ्येन. **3** सावकाशं, यथावसरं. **-ness,** *s.* सौकर्यं, अनायासः, सुखसाध्यता. **2** सुगमत्वं, अवैषम्यं. **3** शांति *f.*, स्वास्थ्यं, अक्लेशः, सुखं. **4** अनुरोधः, आनुकूल्यं, अनुवर्तनशीलता.

Easel, *s.* चित्राधारः, चित्रफलकं.

Easement, *s.* मलविसर्गः. **2** परभूम्याद्यधिकारः.

East, *s.* पूर्वदिश् *f.*, पूर्वा, प्राची, पूर्वाशा, ऐंद्री. **2** पूर्वदेशः, पौरस्त्यजनपदः. *-a.*, **-erly, -ern,** *a.* पूर्व, प्राच् (ची *f.*), पौरस्त्य, प्राच्य, प्राचीन, पूर्वदेशीय, पूर्वदिक्स्थ; प्राङ्मुख; 'the mountain is e. of the sea' समुद्राद् गिरिः पूर्वः; 'the e. mountain' उदयः, उदय-गिरिः-शैलः-अचलः, पूर्वाचलः. **-erly, -ward,** *adv.* पूर्वेण, पूर्वस्यां दिशि पुरः, पूर्वं, प्राक्, पुरस्तात्, पूर्वदेशे.

Eat, *v. t.* अद् 2 P, जक्ष् 2 P, ग्रस् 1 A, खाद् 1 P, अश् 9 P, भक्ष् 10, भुज् 7 A, घस् 1 P, प्सा 2 P, आस्वाद् 1 A, गॄ 6 P, चर्व् 1 P, अभ्यवहृ 1 P, प्रत्यवसो 4 P; 'e. one's own words' स्ववचनमसत्यं-अवितथं-कृ 8 U, स्ववचनेन विसंवद् 1 P; 'e., drink and, be merry' अश्नीतपिबता, खादतमोदता. **-able,** *s.* भक्ष्यं, भोज्यं, अभ्यवहार्यं, खाद्यं, भोज्य-वस्तु-द्रव्यं. **-er,** *s.* खादकः, भक्षकः भोक्तृ *m.*, आशिन् *m.*, अशन-भुज् in comp.; अद्-अद in comp.; 'flesh-e.s' मांसाशिनः, पिशिताशनाः; 'dead-body-e.' कुणप-

भुज्; क्रव्याद्, मांसाद्:, &c. **-ing**, *s.* भक्षणं, खादनं, अशनं, आस्वादनं, भोजनं, &c.; 'e. together' सहभोजनं, जग्धि *f.*; 'e.-house' सिद्धान्नविक्रयशाला

Eaves, *s.* पटलप्रांतः, वलीकः-कं, नीध्रं, वल-(ड)भि-भी *f.* 'e.-dropper' निभृतश्रवणेच्छुः, प्रच्छन्नश्राविन् *m.*

Ebb, *s.* क्षीयमाणा वेला, वेलापरिवर्तनं-परावृत्तः, परावेला. 2 (fig.) क्षयः, हानि *f.*, अपचयः, व्यसनं, नाशः, परिवर्तः; 'e. and flow' व्यसनोदयौ. **-v. i.** क्षि pass., ह्रासं-लयं-गम् 1 P; (वेलावत्) परावृत् 1 A; *See* **Decay.**

Ebony, *s.* कोविदारः, चमरिकः, कुद्दालः, युगपत्रकः.

Ebriety, *s.* मदः, मत्तता, उन्मादः.

Ebriosity, *s.* उन्मादशीलता, क्षीबता.

Ebullition, *s.* उत्सेचनं, उत्सेकः; उद्रेकः, फेनायितं, फेनोद्गमः. 2 अंतःक्षोभः, अंतर्वेगः, चित्तवैक्लव्यं-व्याकुलता, अंतस्तापः.

Eccentric, *a.* सामान्येतर, विषम, विलक्षण, लोकबाह्य, लोकाचारविरुद्ध, विपथगामिन्, व्यभिचारिन्, उत्क्रांतमर्याद, उत्सूत्र. 2 केंद्रभ्रष्ट-च्युत. **-ity**, *s.* वैषम्य, उत्सूत्रता, वैलक्षण्यं, सामान्यविरोधः, लोकाचार-व्यवहार-विरोधः.

Ecclesiastic, *s.* पुरोहितः, आचार्यः, धर्माध्यापकः. **-a.**, **-al**, *a.* धर्मोपदेशविषय, पौरोहित्यसंबंधिन्.

Echo, *s.* प्रतिशब्दः-ध्वनिः-स्वनः-रवः-नादः-वचनं-गर्जनं, अनुरसितं-नादः, प्रतिश्रुत्-ति *f.* **-v. i.** प्रतिस्वन्-ध्वन्-रस्-नद्-स्तन् 1 P, प्रतिरु 2 P, अनुनद्-रस्; कृ 8 U with (*s.*). **-v. t.** Causal of roots above; 'e.-ing the caves' कंदरभुवः प्रतिध्वानयन्-प्रतिध्वनिताः कुर्वन्.

Eclat, *s.* प्रतिष्ठा, शोभा, गौरवं; आडंबरः. 2 स्तुति *f.*, कीर्ति *f.*, ख्याति *f.*, प्रशंसा.

Eclectic, *a.* उद्धारक.

Eclipse, *s.* ग्रहः, ग्रहण, ग्रासः, उपरागः, उपसर्गः, उपप्लवः, ग्रहपीडनं. **-v. t.** ग्रस् 1 A, प्र-आ-च्छद् 10, तिमिरयति (D.), ग्रह् 9 P, उपसृज् 6 P, उप-प्लु 1 A, उपरंज् c. 2 (fig.) प्र-आ-छद्, (गुणवत्तरपात्रेण छाद्यंते गुणिनां गुणाः P. I. 10); प्रत्यादिश् 6 P; 'Urvasi e.s Lakshmi, proud of her beauty' उर्वशी प्रत्यादेशो रूपगर्वितायाः श्रियः (V. 1.). **-ed**, *a.* उपरक्त, उपसृष्ट, ग्रस्त, उपप्लुत, सोपप्लव, ग्रहपीडित. 2 तमोवृत, प्रच्छन्न, मलिनप्रभ. 3 प्रत्यादिष्ट, प्रत्याख्यात.

Ecliptic, *s.* क्रांतिवृत्तं-मंडलं, रविमार्गः.

Economy, *s.* निर्वाहः-हणं, प्रणयनं, नयः, नीति *f.*; 'e. of the house' गृहकार्यनिर्वाहः, गार्हस्थ्यं. 2 परिमित-मित-व्ययः, स्वल्पविवेक-व्ययः, अमुक्तहस्तत्वं. 3 विन्यासः, विरचनं, प्रकल्पनं, संविधानं. 4 (Political) अर्थशास्त्रं, राजनीतिः-शास्त्रं. **-ic, -ical**, *a.* मित-स्वल्प-व्यय, अमुक्तहस्त. 2 कार्यनिर्वाहसंबंधिन्. **-ically**, *adv.* मित-स्वल्प-व्ययेन, अमुक्तहस्त. **-ist**, *s.* मितव्ययिन् *m.*, अमुक्तहस्तः. 2 अर्थशास्त्रज्ञः, राजशास्त्रविद् *m.*, नीतिज्ञः. **-ize**, *v. t.* मितं व्यय् 10 (व्ययपति); स्वल्पशः विनि-प्र-युज् 7 A, 10. **-v. i.** मितव्ययेन गृहकार्याणि निर्वह् c. or प्रणी 1 P.

Ecstasy, *s.* हर्षोन्मादः, आनंदभरः, प्रहर्षः, प्रमदः, अत्यानंदः, संमोहः, उन्मादः. **-ed**, *a.* हर्षोन्मत्त, -पुलकित, हर्षमूढ-जड. **-Ecstatic -al**, *a.* उन्मादिन्, संमोहिन्, परमानंदप्रद मोहक.

Ecumenical, *a.* सर्वसाधारण (णी *f.*).

Eczema, *s.* दद्रु *m.*, पामन् *m.*, पामा.

Edacious, *See* **Greedy.**

Eddy, *s.* आवर्तः, भ्रमः-मि *f.*, भ्रमरकः.

Edentated, *a.* निर्दशन, नीरद.

Edge, *s.* धारा, अग्रं, कोटि-आणि *f.*, पालि-ली *f.*, अणि *f.*-णी. 2 उपांतः, सीमा, प्रांतः, परिसरः, पर्यंतः, उत्संगः; समंतः. 3 अंचलः, दशाः pl. (of garments). 4 तेजस् *n.*, तीक्ष्णता, निशितता; 'e. of a brook' कच्छः, कूलं, तीरं, तटं; 'two or double e.-ed' द्विधार, उभयतस्तीक्ष्ण; कार्यद्वयसाधक; 'setting the teeth on e.' दंतहर्षः. **-v. t.** प्रांतयति (D.), पर्यंतेन सनाथीकृ 8 U. 2 शो 4 P, तिज् c., तीक्ष्णीकृ. **-ed**, *a.* कोटिमत्, धारासनाथ, तीक्ष्ण, सधार; 'sharp e.' तीक्ष्णाग्र, निशितधार. **-less**, *a.* अतीक्ष्ण, धाराहीन.

Edible, *a.* खाद्य, भक्ष्य, भोज्य.

Edict, *s.* शासनं, राजाज्ञा, राजशासनं; 'written e.' आज्ञा-शासन-पत्रं.

Edifice, *s.* भवनं, सदनं, हर्म्यं, मंदिरं, गृहं, प्रासादः, सौधं.

Edify, *v. t.* उत्कृष् 1 P, उन्नी 1 P, उन्नतिं-उत्कर्षं प्राप् c. 2 ज्ञानं वृध् c., शिक्ष् c., उपदिश् 6 P, मोहं-भ्रांतिं-नश् c. or निरस् 4 U. **-ed**, *a.* प्राप्तज्ञान, निरस्तमोह, उपदिष्ट. **-ication**, *s.* ज्ञानप्राप्ति-वृद्धि *f.*, उपदेशः, शिक्षणं. **-ing**, *a.* उपदेशक, ज्ञानवर्धक.

Edit, *v. t.* शोधयित्वा प्रकाश् c., शुध् c. 2 लिख् 6 P. **-ion**, *s.* प्रकाशनं, शोधनं, प्रकटीकरणं. 2 आवृत्ति *f.* **-or**, *s.* प्रकाशकः. 2 लेखकः.

Educate, *v. t.* विनी 1 P, शास् 2 P, अनुशास्, प्रबुध् c., शिक्ष् c., अधि-इ c. (अध्यापयति), संस्कृ 8 U; उपदिश् 6 P, 2 विद्यादानेन पा c. (पालयति) or संवृध् c. or पुष् c. **-ed**, *a.* कृत-गृहीत-उपात्त-लब्ध-विद्य, शिक्षित, प्रबुद्ध; संस्कृतचित्त, विनीत, व्युत्पन्न, कृताभ्यास, लब्धज्ञान. **-ion**, *s.* वि-

नयः, शिक्षा-करणं, अध्यापनं, अनुशासनं, संस्कारः, विद्याज्ञान-ग्रहणं-प्राप्ति *f.*, व्युत्पत्ति *f.*, उपदेशः. 2 पोषणं, संवर्धनं. -**or,** *s.* विनेतृ *m.*, शिक्षकः, प्रबोधकः.

Educe, *v. t.* निष्कृष् 1 P, निर्हृ 1 P.

Eel, *s.* जलव्यालः, अंधाहिः *m.*

Effable, *a.* कथनीय, निर्वचनीय; वाच्य; 'in-e.' अनिर्वचनीय; 'in-e. joy' कोपि आनंदः, किमपि सुखं.

Efface, *v. t.* अप-प्र-व्या-उद्-निर्-मृज् 2 P or c., विनश् c., उच्छिद् 7 P, विलुप् 6 P or c., उद्-हृ 1 P, उन्मूल् 10. -*v. i.* उन्मृज् 2 P. -**ment,** *s.* अपमार्जनं, लोपः, व्यामर्दः; 'e. of colours' वर्णिकोच्छ्वासः (S. 6).

Effect, *s.* कार्यं, नैमित्तिकं; उत्पन्नं, निष्पन्नं, सिद्धि *f.* 2 फलं, परिणामः, फलोदयः, उत्तरफलं, अंतः. 3 अर्थः, प्रयोजनं, गुणः, फलं, प्रभावः. 4 अभिप्रायः, आशयः. 5 निष्पत्ति-सिद्धि *f.*; 'of no e.' निष्फल, निष्प्रयोजन, निर्गुण; 'to take e.' फल् 1 P, मूर्छ् 1 P, (छाया न मूर्छति मलोपहतप्रसादे दर्पणतले S. 7); 'to take no e.' ex. by कुंठ, (यत्रा तपोवीर्यमहत्सु कुंठं K. III. 12); 'to this e.' इति, एतदभिप्राय *a.*; 'to what e.' किमर्थं, केन हेतुना; 'to destroy the e. of' निष्फली-मोघी-कृ 8 U, 'in e.' अर्थतः, वस्तुतः, तत्त्वतः. 6 (E. s.) विभवः, द्रव्याणि, वस्तुसामग्री, रिक्थं. -*v. t.* कृ 8 U, विधा 3 U, सं-निः-पद् c., साध् 5 P or c., निर्वृत् c., निर्वह् c. 2 जन् c., उत्पद् c. -**ive,** *a.* कार्यसाधक, फलवत्, निष्पादक, संपादक, फलोत्पादक; 'e. speech' हृदयग्राहि वचः. -**ual, -Efficacious,** *a.* फलोत्पादक, गुणावह, अमोघ, अव्यर्थ, गुणवत्, सिद्धिकर (री *f.*), कार्यसाधक, सफल. 2 प्रबल, समर्थ, सप्रभाव, क्षम, अलंतम. -**ually,** *adv.* अमोघं, सफलं, निष्पत्तिपूर्वं, अव्यर्थं. 2 प्रभावेण, सामर्थ्येन. -**uate,** *v. t.* कृ, संपद् c., &c.

Effeminate, *a.* क्लीब, दुर्बल, सुकुमार. 2 स्त्रैण (णी *f.*), स्त्रीधर्मन्, स्त्रीवद्वाचारिन्, स्त्रीप्रकृति, स्त्रीगुणविशिष्ट; स्त्रीभाव; 'an e. man' क्लीबः, कापुरुषः, गेहेशूरः. -*v. t.* क्लीबीकृ 8 U, दुर्बली-निष्पुरुषी-कृ. -**ly,** *adv.* क्लीबवत्, नारी-स्त्री-वत्, स्त्रीधर्मानुसारेण. -**Effeminacy,** *s.* क्लीबता, दौर्बल्यं, स्त्रीत्वं, स्त्रैणं, स्त्रीधर्माचरणं, सौकुमार्यं, मृदुता.

Effervesce, *v. i.* बुद्बुदायते (D.), फेनायते (D.), उत्सिच् pass., उच्छूनभिद्, फेनिलीभू. -**ence,** *s.* फेनोद्गमः, उत्सेचनं, बुद्बुदायितं, फेनिलता, उच्छूनीभावः, मंडोद्गमः. 2 उत्तापः, संक्षोभः; आलोडनं. -**ing,** *a.* फेनिल, फेनायमान.

Effete, *a.* जीर्ण, दुर्बल, निःशक्ति, क्षीण, निःसत्त्व, क्षीणशक्ति. 2 वंध्य, निष्फल, मोघ.

Efficacy, *s.* प्रभावः, बलं, सामर्थ्यं, गुणः, शक्ति *f.*, तेजस् *n.*, क्षमता, अमोघता, सफलता, फलोत्पादकत्वं. -**ous,** *a.* प्रबल, समर्थ; *See* **Effectual.**

Efficient, *a.* कार्यसाधक, कार्यसिद्धिक्षम, कार्योपयुक्त, विचक्षण, कर्मक्षम, अलंकर्मीण, निपुण; *See* **Effectual** also. -**ly,** *adv.* अमोघं, सिद्धिपूर्वं, निपुणं, विचक्षणतया. -**Efficiency,** *s.* कार्यक्षमता, कार्यसिद्धिक्षमता, नैपुण्यं, वैचक्षण्यं.

Effigy, *s.* प्रतिमा, मूर्ति-प्रतिकृति *f.*, प्रतिरूपं.

Efflorescence, *s.* पुष्पोत्पादनं, प्रस्फोटनं. 2 वप्रु *m.*

Effluence, *s.* प्रवाहः, निर्गमः, प्रस्रवः, निःस्रवणं.

Effluvium, Effluvia, *s.* उद्गारः, वासः. 2 दुर्गंधः, पूतिगंधः.

Efflux, Effluxion, *s.* प्रवाहः, निस्रावः, ओघः, निःसारः-सरणं, निर्गमः.

Effort, *s.* प्र,-यत्नः, उद्यमः, व्यवसायः, आयासः, चेष्टा, चेष्टितं; 'to make e. s' उद्यम् 1 P; *See* **Attempt.**

Effrontery, *s.* धार्ष्ट्यं, वैयात्यं, निर्लज्जत्वं, प्रागल्भ्यं, प्रतिभानं.

Effulgent, *a.* दीप्तिमत्, तैजस (सी *f.*), उज्ज्वल, शुभ्रभ, तेजस्विन्. -**Effulgence,** *s.* तेजस् *n.*, दीप्ति-कांति *f.*, प्रभा; त्विष् *f.*, शोभा; *See* **Brightness.**

Effuse, *v. t.* प्र-निः-स्रु c., प्रसृ 6 P, उत्-वि-सृज् 6 P, वर्ष् c., नि-अव-सिच् 6 P. -**ion,** *s.* उत्सर्गः, निषेकः, स्रावः, मोक्षणं, अवपातनं.

Egg, *s.* अंडं, पेशि-शी *f.*, कोषः-शः; 'lay e. s' अंडमोक्षणं कृ 8 U, अंडानि सृ 2 A; 'e. on' *v. t.* प्रोत्सह् c.; *See* **Prompt.**

Eglantine, *s.* अरण्यजपा-वा.

Ego, *s.* जीवात्मन् *m.* -**ism,** *s.* आत्म-हितं-लाभः. 2 अहंप्रत्ययः, अहंभावः. -**ist,** *s.* आत्मश्लाघिन् *m.* 2 अहंप्रत्ययवादिन्.

Egotism, *s.* अहंकारः, आत्मश्लाघा-स्तुति *f.*, आत्माभिमानः, ममता. -**Egotist,** *s.* आत्मश्लाघिन्-अहंकारिन्-आत्माभिमानिन् *-m.*, विकत्थनशीलः. -**ic, -ical,** *a.* अहंकारिन्, दृप्त, गर्वित; *See* **Arrogant.** -**ically,** *adv.* सदर्पं, आत्मश्लाघापूर्वं.

Egregious, *a.* अत्यंत, असाधारण (णी *f.*), विशिष्ट, प्रख्यात, प्रसिद्ध, उत्तम, प्रमुख ; oft. by अति pr.; 'an e. rogue' सुप्रसिद्धः शठः; अतिमूर्खः, &c. -**ly,** *adv.* अत्यंतं, अतीव, भृशं, अतिमात्रं, सातिशयं.

Egress, *s.* निर्गमः, निष्क्रमः, निर्याणं, निःसरणं, अपसारः, निर्गति *f.*

Eight, *a.* अष्टन्, अष्टौ; 'in e. ways.' अष्टधा; 'e. times' अष्टकृत्वः; 'e.-fold' अष्टगुण.

Eighteen, *a.* अष्टादशन्.

Eighty, *a.* अशीति *f.*

Either, *pron., a.* अन्यतर; 'on e. side' उभयतः. *-conj.* (-or) वा-वा, or वा singly.

Ejaculate, *v. i.* सहसा उदीर् 10 or उच्चर् c., प्रार्थनां उदाहृ 1 P. 2 उद्गृ 6 P. उत्क्षिप् 6 P. **-ion,** *s.* उद्गारः, आक्रंदनं, सहसा उदीरणं, उच्चारणं.

Eject, *v. t.* निरस् 4 U, निराकृ 8 U, निःसृ c.; *See* **Drive away, Discharge. 2** उत्क्षिप्-उद्गृ-6 P. **-ion,** *s.* निःसारणं, निराकरणं, निष्कासनं; अधिकाराद् भ्रंशनं.

Ejulation, *s.* विलपनं, परिदेवनं, आर्तनादः, आक्रंदनं.

Eke, *v. t.* वृध् c., विस्तृ c., प्रसृ c., तन् 8 U *-adv.* अपिच.

Elaborate, *v. t.* महाश्रमेण साध् c., or निष्पद् c. or निर्मा 3 A or विधा 3 U or प्रक्लृप् c. **-ed,** *a.* बहुश्रमासिद्ध, महाप्रयत्नकृत-विरचित-प्रकल्पित. **-ly,** *adv.* महायत्नेन, बहुश्रमेण, महायासेन. **-ion,** *s.* बहुश्रमेण निर्माणं.

Elapse, *v. i.* व्यति-इ 2 P. अतिक्रम् 1 U, 4 P, व्यतिक्रम्, गम् 1 P: 'days having e.-ed' दिनेषु गच्छत्सु.

Elastic, *a.* स्थितिस्थापक, प्रकृतिपाणक. **-ity,** *s.* स्थितिस्थापकता-त्वं.

Elate, *v. t.* उत्सिच् 6 P, दृप् c., आध्मा 1 P. दर्पेण उद्-श्वि c. or उद्-हन् 2 P: *See* **Puff. 2** प्रहृष् c., प्रमुद् c., उल्लस् c. *-a.,* **-ed,** *a.* दर्पाध्मात, उद्धत, गर्वित, उत्सिक्त, मदोद्धत, दृप्त, गर्वोच्छून. 2 प्रहृष्ट, प्रमुदित, सोल्लास, हृष्टचित्त. **-ion,** *s.* गर्वः, दर्पः, औद्धत्यं, प्रहर्षः, चित्तोल्लासः.

Elbow, *s.* कूर्परः, कफ(फो)णि *m. f.* 2 वंकः, पुटभेदः. *-v. t.* कूर्परेण आहत्य बहिष्कृ 8 U.

Elder, *a.* ज्यायस्, वरीयस्, अग्रज, पूर्वज, वर्षीयस्, वयोज्येष्ठ; 'e. brother' अग्रजः, अग्रजन्मा, ज्यायान् भ्राता. *-s.* गुरुः, वृद्धः; 'e. s, elderly persons' गुरुजनः, गुरवः, आर्यजनः, वृद्धाः.

Eldest, *s.* ज्येष्ठ, वर्षिष्ठ, वरिष्ठ, श्रेष्ठ, सर्वज्येष्ठ.

Elect, *v. t.* वृ 5 U or 10 (वरयति), वृ 9 U. 2 ग्रह् 9 P, आदा 3 A, स्वीकृ 8 U. 3 नियुज् 7 A, 10, निरूप् 10. निर्वस् c., 'self-election' स्वयंवरः; 'self-e. ed bride' स्वयंवरवधूः; 'e. ed him as her husband' पतित्वेन तं वरयामास. *-a.,* **-ed,** *a.* नियुक्त, निरूपित, वृत, निर्वाचित; व्याहृत; 'a person e.' निर्वाच्यः, नियोगिन् *m.* निर्वाचितः. **-ion,** नियोजनं, वरणं, निर्वाचनं, वृति *f.* **-ive,** *a.* जनैर्नियुक्त; 'e. right' वरणाधिकारः; 'e. municipality' जनैर्नियुक्तसभा ग्रामपालिका. **-or,** *s.* नियोजकः, निर्वाचकः, वरणाधिकारविशिष्टः; 'body of e. s, electoral body' नियोजकगणः.

Electer, Electrum, *s.* कांस्यं, मिश्रधातु *m.*

Electric, *a.* वैद्युत (ती *f.*), विद्युन्मय (यी *f.*), विद्युद्विषय. **-ity,** *s.* तडित्-विद्युत्-वैद्युत-शक्ति *f.*

Electrubus, *s.* विद्युत्-यानं-वाहनं.

Electrocute, *s.* विद्युन्मरणेन दंड् 10.

Electuary, *v. t.* लेह्यं, अवलेहः.

Eleemosynary, *a.* दरिद्रार्थ, दरिद्रोपकारिन्.

Elegant, *a.* चारु, ललित, सुंदर, सुरूप, लावण्यवत्, श्लील, अग्राम्य, सुभग. 2 (As composition) सुरस, ललित, चारु. **-ly,** *adv.* सविन्यासं, चारु, ललितं. **-Elegance, -cy,** *s.* चारुता, सौंदर्यं, विलासः, लावण्यं, शोभा, विभ्रमः, लालित्यं; 'e. of words' पदलालित्यं.

Elegy, *s.* करुणरसं गीतं, शोकगर्भ-गीति *f.*

Elegiac, *a.* करुणामय (यी *f.*), शोकप्रधान.

Element, *s.* भूतं, बीजं, मूलं, मूलवस्तु *n.* 2 तत्त्वं. 3 अवयवः, भागः, अंशः. 4 आरंभः, उपक्रमः, मूलतत्त्वं, बीजभूतं ज्ञानं. 5 वस्तुमात्रं; 'out of his e.' अस्थाने. **-al,** *a.* भौत (ती *f.*), भौतिक (की *f.*). **-ary,** *a.* अव्याकृत, शुद्ध, निरवयव. 2 मूल in comp. प्रारंभक.

Elephant, *s.* गजः, हस्तिन्-करिन् *m.*, मातंगः, मतंगजः, कुंजरः, नागः, वारणः, इभः, द्विरदः, द्वि-अनेक-पः, दंतिन् *m*, दंतावलः, स्तंबेरमः; 'she-e.' करिणी, करेणु *f.*-णुका, वशा, धेनुका; 'a young e.' कलभः, करिशावकः; 'e. driver' हस्तिपः-पकः, आधोरणः, महामात्रः, निषादिन् *m.*; 'wild e.' वनगजः, वन्यः करी; 'furious or rutting (e.)' मदोत्कटः, मदकलः. प्रभिन्नः, गर्जितः, मत्तः; 'e. out of rut' उद्वांतः; निर्मदः; 'head of a herd of e. s' यूथनाथः, यूथपः; 'herd of e. s' हास्तिकं, गजता, गजयूथं; 'war e.-s' गजघटा; 'e. s of the quarters' दिग्गजाः; 'frontal globe of an e.' कुंभः; 'e.'s fore-head' ललाटं, अवग्रहः; 'his eyeball' इ(ई)षि(षी)का, अक्षिकूटकं 'corner of his eye' निर्याणं; 'root of his ear' चूलिका; 'his withers' आसनं, स्कंधदेशः; 'his side' पार्श्वभागः, पक्षभागः; 'the temple-juice' मदः, दानं; 'water emitted from the trunk' वमथुः, करशीकरः; 'his roaring' बृंहितं, गर्जितं; 'the whip to strike him' तोत्रं, वेणुकं; 'binding-post' आलानं; 'binding chains' शृंखलं, अंकुशः, निगडः; 'caparisoning of an e.' कल्पना, सज्जना; 'coloured housings' प्रवेणी, आस्तरणं, वर्णः. परिस्तो(स्तो)मः, कुथः.

Elephantiasis, *s.* श्लीपदं, शिलीपदं.

Elevate, *v. t.* उन्नम् c. (उन्नमयति), उच्छ्रि c., उद्यम् 1 P, उत्कृष् 1 P; उत्था c., (उत्थापयति), उन्नी 1 P, अधिरुह् c. (रोपयति), उन्नति-उत्कर्ष-नी or कृ 8 U; 'e. to a high office' उन्नतपदे नियुज् 7 A, 10, उत्कृष्टपदं प्राप् c. **-ed,** *a.* अधिरोपित, उन्नीत; उन्नतपदनियुक्त. 2 उच्छ्रित, उत्तुंग, उन्नत, सोच्छ्राय; *See* **High.** **-ion,** *s.* उन्नति *f.*, उत्कर्षः; उच्छ्रायः, उत्थापनं, अधिरोपणं, उन्नपदप्रापणं, उदयः. 2 उत्सेधः, उत्तुंगता, उच्छ्रायः, उन्नतस्थानं; *See* **Height.**

Eleven, *a.* एकादशन्. **-Eleventh,** *a.* एकादश (शी *f.*); 'what is the use of doing things at the e. hour' प्रोद्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः (Bh. II. 88).

Elf, *s.* वेतालः, भूतः, पिशाचः, अपदेवता. **-ish,** *a.* पैशाच (ची *f.*).

Elf-lock, *s.* जटा, सटा.

Elicit, *v. t.* निर्गम् c. (गमयति), निष्कृष् 1 P, उद्धृ c., निःसृ c., प्रकाश् c., अपवह् 1 P or c., आविष्कृ 8 U, निर्णी 1 P, ज्ञा 9 U or c. (ज्ञापयति). **-ation,** *s.* निष्कर्षणं, निर्गमनं, &c.

Elide, *v. t.* लुप् 6 P or c. **-Elision,** *s.* लोपः.

Eligible, *a.* वरणीय, नियोज्य, ग्राह्य, आदेय.

Eliminate, *v. t.* नश् c., निष्कस् c., विलुप् 6 P or c., निराकृ 8 U. **-ion,** *s.* लोपः, नाशः, आहरणं, अपनयनं.

Elite, *s.* विशिष्टः; ex. by सार-विशेष-रत्न in comp.

Elixir, *s.* रसायनं, तेजोवर्धनं.

Ellipse, *s.* अंडवृत्तं, उपवृत्तं-मंडलं. **-Elliptic,** *a.* अंडाकार, अंडाकृति.

Ellipsis, *s.* न्यूनपदं, अध्याहारः, शब्दलोपः. 2 पद-वाक्य-आकांक्षा; 'supplying an e.' आकांक्षापूरणं. **-Elliptical,** *a.* न्यूनपद; अध्याहार्य, अभ्यूहनीय.

Elocution, *s.* वाक्शक्ति *f.*, वक्तृत्वं, वाक्पटुता, वाग्मिता. 2 व्याहारः, वाणी.

Elongate, *v. t.* दीर्घीकृ 8 U, आयम् 1 P; वितन् 8 U. **-ed,** *a.* आयत, आयामवत्, लंबाकृति, वितत. **-ion,** *s.* दीर्घीकरणं, प्रतानं, विततिः *f.*, आयति *f.*

Elope, *v. i.* अलक्षितं पलाय् 1 A or अपसृप् 1 P. **-ment,** *s.* गूढं स्वपसर्जनं, पलायनं.

Eloquent, *a.* वाग्मिन्, वागीश, वाग्विदग्ध, वक्तृ, वाक्पटु, शब्दचतुर. **-ly,** *adv.* वाग्विभवेन, शब्दचातुर्येण, वाक्पटुतया. **-Eloquence,** *s.* वाक्पाटव-शक्ति *f.*, वाग्मिता, वाग्विभवः, वक्तृत्वं.

Else, *a.* अन्य-इतर-अपर-*pron. a.*, भिन्न, व्यतिरिक्त; 'what e.' किमन्यत्, अथ किं; 'who e.' कोऽपरः. **-conj.** न (नो) चेत्, अन्यथा, इतरथा; एतद्विना, एतद्व्यतिरेकेण; 'e. where' अन्य-इतर-पर-त्र, स्थानांतरे, भिन्न-अन्य-स्थाने.

Elucidate, *v. t.* व्याख्या 2 P, व्याकृ 8 U, वि-वृ 5 U, स्पष्टी-विशदी-कृ; *See* **Explain.** **-ion,** *s.* व्याख्यानं, स्पष्टीकरणं, विवरणं. **-or,** *s.* व्याख्यातृ *m.*, प्रकाशकः, विवरणकृत् *m.*

Elude, *v. t.* कौशलेन परिहृ 1 P, वंच् 10, छलेन अपसृप्-निर्गम् 1 P or पलाय् 1 A, (with abl.); 'e. ing the senses' इंद्रियागोचर; 'it e. s grasp' ग्रहीतुं न शक्यते. **-Elusion,** *s.* छलेन परिहरणं; अलक्षितं अपसरणं or निर्गमः. **-Elusive,** *a.* निर्गमपर, परिहारिन्. **-Elusory,** *a.* छलिन्, मायिन्.

Elysium, *s.* वैकुंठ, स्वर्गः, नंदनं, आनंदस्थानं. **-Elysian,** *a.* परमानंदप्रद, स्वर्गीय.

Emaciate, *v. t.* कृशीकृ 8 U, क्षै c. (क्षपयति) क्लिश् 9 P, ग्लै c. (ग्लपयति-ग्लापयति), शुष् c., क्षीण *a.* कृ. **-v. i.** क्षै-ग्लै 1 P, शुष् 4 P, विशृ-क्षि-pass., कृशीभू. **-ed,** *a.* क्षीण, क्षीणशरीर-शक्ति, कृश, क्षाम, ग्लान, क्षीण-शुष्क-मांस; अपचित; 'e. by hunger' क्षुत्क्षामकंठ. **-ion,** *s.* कृशता, क्षामता, क्षीणता कार्श्यं, शरीरशोषणं, मांसक्षयः, अपचयः.

Emanate, *v. i.* उत्पद् 4 A, निर्गम् 1 P, निःसृ 1 P, उत्-प्र-भू 1 P, जन् 4 A, निःसृ 1 P, प्रवृत् 1 A. **-ion,** *s.* उत्पत्ति *f.*, उद्भवः, प्रभवः, उद्गमः, निर्गमः, प्रवृत्ति *f.* **-ive,** **-Emanant,** *a.* उद्भूत, उत्पन्न, जात, ज, जन्य, प्रभव in comp.

Emancipate, *v. t.* मुच् 6 P or c., वि-निर्-; मोक्ष् 10, उद्धृ 1 P, निस्तॄ c., विमुच् 6 P. **-ion,** *s.* विमोचनं, मोक्षः, मुक्ति *f.*, उद्धारः, निस्तारः. 2 मुक्ति *f.*, मोक्षः; *See* **Beatitude.** **-or,** *s.* मोचकः, मोक्षकः.

Emasculate, *v. t.* वृषणौ छिद् 7 P or कृत् 6 P, पुंस्त्वं हृ 1 P, षंढी-क्लीबी-कृ 8 U. **-ed,** *a.* हतवीर्यः, हृतपुंस्त्वः, छिन्नवृषणः, शुष्कशून्यः, षंडः-ढः, क्लीबः, नपुंसकः. **-ion,** *s.* वृषणच्छेदः, पुंस्त्वहरणं.

Embale, *v. t.* भांडं कृ 8 U, एकत्र कृ.

Embalm, *v. t.* रक्ष् 1 P; तैले निक्षिप् 6 P, क्षयात् रक्ष्. 2 सुरभीकृ 8 U, आमोदेन पूर् 10, वास् 10.

Embank, *v. t.* सेतुना-बंधेन-बंध् 9 P. **-ment,** *s.* सेतु-बंध-बंधः, मृत्तिकाबंधः, चयः.

Embar, *v. t.* निरुध् 7 U, निषिध् 1 P.

Embargo, *s.* निरोधः, वाणिज्यकर्मनिषेधः, अवरोधः.

Embark, *v. t.* नौकायां नि-प्र-विश् c. or निवश् 3 U. —*v. i.* नावं or पोतं-आ-अधि-रुह् 1 P, or प्रविश् 6 P. **2** व्या-पृ 6 A. अभि-युज् pass. (with loc.) ; प्रारभ् 1 A (with acc.). **-ation,** *s.* नौकारोहणं-रोपणं-प्रवेशनं. **2** व्यापारः, अभियोगः, प्रारंभः, उपक्रमः.

Embarrass, *v. t.* आकुलयति (D.). वि-व्या-मुह् c., व्यग्रीकृ 8 U, संभ्रम् c. (भ्रमयति), आकुलीकृ; ' I am really e. ed ' सत्यमाकुलीभूतोस्मि (S 2) **2** बाध् 1 A. क्लिश् 9 P, उपरुध् 7 U, अभिभू. **-ed,** *a.* आ-व्या-कुल, व्यग्र, मोहित, संभ्रांत, मूढ. **2** बाधित, उपरुद्ध; क्लिष्ट, अभिभूत; ' in e. circumstances ' आपद्गत, दुःस्थ, कृच्छ्रगत, दुर्गत; ' e. smile ' विलक्षस्मित. **-ment,** *s.* व्याकुलता. व्यग्रता. संभ्रमः, व्यामोहः. आकुलत्वं, क्लेशः, बाधः-धा, दुःखं, उपरोधः.

Embassy, *s* दौत्यं, दूतधर्मः-क्रिया; ' sent on an e. ' दूतः, दौत्येन प्रस्थापितः.

Embattle, *v. t.* व्यूह् 1 U or c., व्यूहेन रच् 10 or सज्जीकृ 8 U or व्यव-स्था (स्थापयति), व्यूहरचनां कृ. **-ed,** *a.* सन्नद्ध, सज्जीकृत, व्यूहेन रचित.

Embedded, *a.* निहित, निविष्ट, न्यस्त.

Embellish, *v. t.* भूष् 10, अलंकृ 8 U, मंड् 10, शुभ् c., प्राञ्ज् c., परिष्कृ, प्रसाध् c **-ment,** *s.* प्रसाधनं, भूषणं; *See* **Ornament. 2** नेपथ्यं, आहार्यं, वेशः, आकल्पः.

Embers, *s.* भासितं, भस्मन् *n.*; अंगारशेषं; अंगारोच्छिष्टं.

Embezzle, *v. t.* छलेन आत्मसात्कृ 8 U, स्वकीयं कृत्वा उप-विनि-युज् 7 A, 10; ग्रस् 1 A. **-ment,** *s* छलेन अपहारः or उपयोगः or आत्मसात्करणं, ग्रसनं; अप-नि-ह्नवः.

Embitter, *v. t* तिक्तीकृ 8 U. **2** प्रकुप् c, उद्-दीप् c , कलुषीकृ. **3** क्लिश् 9 P. दु 5 P

Emblazon, *v. t.* विभूष् 10, मंड् 10.

Emblem, *s* लक्षणं, लांछनं, केतनं, केतुः, व्यंजनं, संज्ञा, ध्वजः, चिह्नं, लिंगं, पताका. **-atic, -atical** *a.* लाक्षणिक (की *f.*). व्यंजक, बोधक. लिंगिन्, सूचक, द्योतक.

Embody, *v. t.* सशरीर *a.* कृ 8 U. शरीरेण युज् 10 or सनाथीकृ. **2** संग्रह् 9 P, समाहृ 1 P. एकी-एकत्र-कृ. **-ed,** *a.* मूर्त, शरीरबद्ध, देहवत्, मूर्तिमत्, शरीरिन्; ' the e. spirit ' शरीराभिमानी आत्मा. **-ment,** *s.* शरीरिता, देहवत्त्वं, मूर्तिमत्ता. **2** मूर्ति *f.* करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथा (U 3) ' the e of pathetic sentiment &c ' **3** संग्रहः, सन्निपातः, समाहारः, एकीकरणं.

Embolden, *v t* प्रोत्सह् c . आश्वस् c . निर्भय *a.* कृ.

Embosom, *v t* क्रोडीकृ 8 U **2** छिद् 4 P **3** परिवेष्ट् 10

Emboss, *v. t.* गंडाकारेण परिष्कृ 8 U or उपस्तम्भ् c.

Embouchure, *s.* मुखं (of a river or a wind instrument).

Embow, *v. t.* कुञ्च् 6 P; *See* **Bend.**

Embowel, *v. t.* अंत्राणि अपनी or निर्हृ 1 P.

Embowered, *a.* कुंजसनाथ, निकुंजित.

Embrace, *v. t.* आलिंग् 1 P, आश्लिष् 4 P; परि-, ष्वंज् 1 A, उपगुह् 1 U; *See* **Clasp. 2** स्वी-अंगी-कृ 8 U; ग्रह् 9 P, आदा 3 A, अभ्युपगम् 1 P. **3** परिग्रह्, व्याप् 5 P, प्रतिसंह् 1 P, समाविश् c. **4** परिवृ 5 U. परिवेष्ट् 1 A or c. **-s.** सं-आ-श्लेषः, आलिंगनं, परिरंभः, उपगूहनं, परिष्वंगः.

Embrasure, *s.* प्राकारच्छिद्रं, जालकं.

Embrocate, *v. t.* (औषधीयजलेन) लिप् 6 P, अंज् 7 P; मृद् 9 P, घृष् 1 P. संवह् c. **-ion,** *s.* मर्दनं, लेपनं, संवाहनं. **2** विलेपः-पनं, उपदेहद्रव्यं.

Embroglio, *s.* कलहकारणं. **2** वैरं, विरोधः. **3** वैमत्यं.

Embroider, *v. t.* सूच्या पुष्पादिकं सिव् 4 P or चित्र् 10, कार्मिकवस्त्रं कृ 8 U; ' an e. ed cloth' चित्रितं-कार्मिकं-वस्त्रं. **-er,** *s.* कार्मिकवस्त्रकृत् *m.*, सूचिकर्मोपजीविन् *m.* **-y,** *s.* सूचिकर्मन् *n.*, शिल्पं.

Embroil, *v. t.* संक्षुभ् c., आकुलीकृ 8 U, संकृ 6 P, संकुलीकृ; विरागं उत्पद् c. **-ment,** *s.* संक्षोभः, सांकर्यं, संभ्रमः, आकुलत्वं.

Embryo, Embryone, *s.* गर्भः, भ्रूणः; ' in e. ' गर्भस्थ, गर्भावस्थायां वर्तमान; (fig.) अपरिणत, अपरिपक्व. **2** आ-प्रा-रंभः; उपक्रमः.

Emend, *See* **Amend. -ator,** *s.* शोधकः, समाधातृ *m.*

Emerald, *s.* मरकतं, गारुत्मतं, अश्मगर्भः. हरिन्मणिः; ' e.-like ' मारकत (ती *f.*), मरकतसदृश (शी *f.*)

Emerge, *v. i.* (सलिलात्) उन्मस्ज् 6 P, उत्था 1 P, निर्गम्-निःसृ 1 P; स्यन्द् 1 P. **2** आविर्भू 2 P, उदि 2 P, निर्भा 1 P, दृष्टिगोचर *a.* भू, दृश् pass., प्रकाशतां गम् &c., **-ence, -cy,** *s.* संकटं, विपत्समयः, आपद् *f.*, आकस्मिकसंभवः. **2** अवसरः, प्रस्तावः; प्रयोजनं, आवश्यकत्वं; ' according to e. ' यथाप्रयोजनं, यथावसरं, प्रसंगवशात्. **-ent,** *a.* उन्मज्जत् **2** आकस्मिक (की *f.*), अकस्मादुद्भूत, अत्यावश्यक (की *f.*), अपरिहार्य **-Emersion,** *s.* उत्थानं, उन्मज्जनं; स्यागः. **2** आविर्भावः, उदयः, &c.

Emery, *s.* उत्तमलोहं.

Emetic, *s.* वमनं, वांतिकृत् औषधं. **-a., -al,** *a.* वांतिकर (री *f.*).

Emeute, *s.* संमर्दः, तुमुलं-लः, कोलाहलः, विप्लवः.

Emigrate, *v. i.* देशांतरं अधिवस्तुं स्वदेशं त्यज् 1 P. **-ion,** *s.* °स्वदेशत्यागः. **-Emigrant,** *s.* °त्यागिन् *m.*

Eminent, *a.* उत्कृष्ट, विशिष्ट, प्रमुख, उत्तम, परम, श्रेष्ठ, प्रवर, वरेण्य, प्रधान. **2** विश्रुत, लब्धप्रतिष्ठ-वर्ण, महायशस्क, सुविख्यात, प्रख्यात; 'of e. qualities' गुणाढ्य. **3** उच्च, उन्नत, उच्छ्रित.**-ly,** *adv.* अत्यंतं, भृशं, अतिशयेन, अत्यर्थं, अति pr. **-Eminence,** *s.* उन्नतभूमि *f.*, उच्छ्रायः, उच्चस्थानं, उत्सेधः, उच्चभूभागः. **2** उत्कर्षः, विशिष्टता, परमपदं, श्रेष्ठत्वं, ख्याति *f.* प्रतिष्ठा, उन्नति *f.*, प्रकर्षः, गौरवं.

Emissary, *s.* दूतः, वार्ताहरः, संदेशहरः. **2** चरः, चारः, गूढदूतः,अपसर्पः, प्रणिधिः, स्पशः.

Emit, *v. t.* वि-निर्-मुच् 6 P, निःक्षिप् 6 P, उद्गॄ c., निःसृ c., उत्-वि-सृज् 6 P, उद्-गॄ 6 P, उद्वम् 1 P, निर्गम् c. (गमयति); निःसृ c.. मोक्ष् 10. **-Emission,** *s.* उद्गारः; विमोचनं, उत्सर्गः, स्रावः, उदीरणं, उद्गमनं **2** (Of semen) रेतः-क्षरणं-स्खलनं, वीर्यनिषेकः, रेतःस्रुति *f.*, निषेकः.

Emmet, *s.* पिपीलिका.

Emmew, *v. t.* पंजरे निरुध् 7 U.

Emolliate, *See* **Soften.**

Emollient, *s.* अभ्यंजनं, विलेपनं, स्नेहनं. **-a** स्निग्ध, स्नेहन (नी *f.*), चिक्कण. **2** शांतिद, सुखावह.

Emolument, *s.* लाभः, फलं, आगमः, प्राप्ति *f.*, आयः, उदयः.

Emotion, *s.* विकारः, विकृति *f.*, भावः, रागः, चित्तविकारः, विक्रिया, मनोधर्मः-वृत्ति *f.* **2** उत्तापः, चित्तक्षोभः, मनस्तापः, अंतर्वेगः, आकुलता, आवेगः, संक्षोभः; 'under e.' विकृतचेतस्, विकारवश *a.*; 'e. of sorrow' शोकावेगः. **3** रसः, भावः; 'e. of love' शृंगाररसः. **-al,** *a.* भाव-विकार-विशिष्ट,विकारप्रेरित.

Empale, *v. t.* **Encircle,** q. v. **2** शूले आरुह् c. (रोपयति) or निविश् c. **-ment,** *s.* शूलारोपणं; 'deserving e.' शूल्य.

Emperor, *s.* सम्राज् *m.*, अधिराजः, अधीश्वरः, चक्रवर्तिन् *m.*, सार्वभौमः, मंडलेश्वरः, राजाधिराजः. **-Empress,** *s.* अधि-महा-राजाधिराज्ञी.

Emphasis, *s.* अवधारणं, गुरूच्चारणं. **-Emphasize,** *v. t.* गौरवेण उच्चर् c., गुरुयति (D.). **-Emphatic,** *a.* दृढ, निश्चित, गौरवेण उच्चारित, अवधारणीय. **-ally,** *adv.* सुदृढं, सनिश्चयं, सावधारणं, सपरिच्छेदं.

Empire, *s.* आधिराज्यं, साम्राज्यं, आधिपत्यं, ऐश्वर्यं, ईशत्वं, प्रभुत्वं. **2** राष्ट्रं, राज्यं, विषयः.

Empiric, *s.* कुचिकित्सकः, छद्म-कु-वैद्यः. **2** परीक्षकः. **-a.**, **-al,** *a.* अशास्त्रसिद्ध, आयुर्वेदविरुद्ध, छाद्मिक (की *f.*); प्रयोगैकविषय, प्रयोगमात्रसिद्ध. **-ally,** *adv.* आयुर्वेदविरुद्धं, अविधया, अशास्त्रानुसारेण, प्रयोगज्ञानमात्रेण. **-ism,** *s.* कुचिकित्सा, &c.

Emplastic, *a.* चिक्कण, सांद्र, लेप्य.

Employ, *v. t.* नियुज् 7 A, 10 ; अधिकृ 8 U, विधा 3 U, व्यापृ c., प्रवृत् c.; 'e. as a messenger' प्रतिशास् 2 P. **2** प्र-उप-युज्, उपयुज् 7 U, सेव् 1 A, व्यवहृ c. अभ्यस्, 4 P. **-ee,** *s.* नियोज्यः, अधिकृतः. **-er,** *s.* प्र-नि-योजकः, प्रवर्तकः, व्यापारयितृ *m.*, अधिकारिन्-स्वामिन् *m.* **-ment,** *s.* नियोगः. व्यापारः, व्यवसायः, उद्योगः, कार्यं, कार्ययोगः; जीविका, व्यवहारः, वृत्ति *f.*; 'his e. was to chop wood' काष्ठच्छेदनवृत्तिरसौ; 'out of e.' निर्वृत्ति, क्षीणवृत्ति, निर्व्यापार. **2** प्रयोगः. उपयोगः.,व्यवहारः. **3** अधिकारपदं. पदं.

Empoison, *v. t.* तीक्ष्णरसं-विषं-दा 3 U.विषप्रयोगेण नश् c **2** विषेण दिह् 2 U or अंज् 7 P.

Emporium, *s.* वाणिज्यस्थानं. निषद्या.

Empower, *v. t.* अधिकृ 8 U, नियुज् 7 A 10, क्षमतां-अधिकारं-दा 3 U.

Empty, *a.* शून्य, परिशून्य, शून्यगर्भ, रिक्त.**2** विरस. निःसार, असार, फल्गु, निःसत्त्व; 'e.-headed' मंदधी, अल्पबुद्धि, दुर्मति ; 'an e. vessel makes most noise' अर्धो घटो घोषमुपैति नूनं. **-v.** 'रिच् 7 U, शून्यीरिक्तीकृ 8 U **2** सारं हृ 1 P, निःसत्वीकृ. **3** तोयं पत् c.. अव-तॄ 1 P, स्रु 1 P. विश् 6 P (कुल्या सागरं वर्जयित्वा महानद्यवतरति S. 3) 'e. s itself &c.' **-ness.** *s.* रिक्तता, शून्यता ; निःसारता, &c.

Empurple, *v. t.* अरुणी-लोहिती-कृ 8 U.

Empyreal, *a.* आग्नेय-तेजोमय (यी *f.*).

Empyrean, *s.* उत्तमस्वर्गः, वैकुंठं. तेजोलोकः.

Emulate, *v. t.* स्पर्ध् 1 A, प्रतिस्पर्ध्, संघृष् 1 P (with instr.); विजि desid. (विजिगीषते), अभिभवितुं यत् 1 A or उद्यम् 1 P, अहमहमिकया यत्; *See* **Compete.** **-ion,** *s.* स्पर्धा. विजिगीषा, संघर्षः. अहमहमिका. **-ive, -Emulous,** *a.* प्रतिस्पर्धिन्, विजिगीषु, जयेच्छु. **-s.** विजिगीषुः,सपत्नः,प्रतिस्पर्धिन् *m.*

Emulsion, *s.* पायसं, पयस्यं.

Emunctory, *s.* शरीरमलपथः, देहमलनिर्गमः.

Enable, *v. t.* Gen. ex. by शक्य; 'this will e. you to go back' अनेन तव परावर्तनं शक्यं ; शक्ति-सामर्थ्य-दा 3 P, समर्थक्षम-शक्त *a.* कृ 8 U.

Enact, *v. t.* कृ 8 U. विधा 3 U. निष्पद् c. **2** व्यव-स्था c. (स्थापयति), विधिं-व्यवस्थांकृ, प्रशास् 2 P. शासनं कृ ; 'it is e. ed as follows' अयं विधिः क्रियते, एवं व्यवस्था-

व्यते. 3 नद् 10, अभिनी 1 P, निरूप् 10. -ment, s. विधिः, शासनं, व्यवस्था शासनपत्रं.

Enamoured, *a.* सानुराग, आसक्त, अनुरक्त, बद्धभाव, कामासक्त (with loc.); 'the king was e. of her' नृपस्तस्यां बद्धभावः, आसक्तानुरागः, प्रीतिं बबंध; 'to be e.' अनुरक्त-आसक्त pass., आसक्त &c. भू.

En bloc, *adv.* साकल्येन, संघशः, गणशः.

Encage, *v. t.* पंजरे निरुध् 7 U or बंध् 9 P.

Encamp, *v. t.* (सैन्यं) निविश् c., समावस् c. —*v. i.* निविश् 6 P, समावस् 1 P. -ment, *s.* निवेशनं, समावासः. 2 शिबिरं, निवेशः.

Encave, *v. t.* कंदरे प्रच्छद् 10 or गुह् 1 U.

Enciente. *See* **Pregnant.**

Enchafe, *v. t.* संतप्-प्रकुप्-रुष् c.

Enchain, *v. t.* निगडैः बंध् 9 P, निगडयति (D.), खिलीकृ 8 U, अव-नि-रुध् 7 U. 2 आकृष् 1 P, हृ 1 P, निरुध्.

Enchant, *v. t.* मंत्रैर्वशीकृ 8 U or मुह् c. अभिचर् c., अभिमंत्र् 10. 2 (fig.) हृ 1 P, आकृष् 1 P, विलुभ् c. 'I was quite e-ed with thy ravishing melody' तवास्मि गीतरागेण हारिणा प्रसभं हृतः (S. 1). -er, *s.* वि-मोहकः, ऐंद्रजालिकः, मायिन् m.; 'e. of snakes' व्यालग्राहिन् m., आ(अ)हितुंडिकः. -ing, *a.* मनोहर, मोहिन्, हारिन्. -ment, *s.* माया, योगः, इंद्रजालं, मोहः, कुहकः, अभिचारः. -Enchantress, *s.* मायिनी, मोहिनी, योगिनी.

Enchase, *v. t.* मणि-धा 3 U, प्रतिबंध् 9 P, अनुव्यध् 4 P, खच् 10 (खचयति).

Encircle, *v. t.* परि-वृ 5 U, परिवेष्ट् 1 A or c., परिगम् 1 P, परि-इ-या- 2 P, वलयति-मंडलयति (D.), वलय-रसना in comp. 2 Embrace, q. v.

Enclose, *v. t.* आ-परि-वृ 5 U, परिवेष्ट् 1 A or c. 2 नि-सं-अव-रुध् 7 U. 3 प्राचीरेण परिवेष्ट् or आवृ or अवरुध्, परिक्षिप् 6 P. 4 आवेष्ट्, आ-सं-छद् 10. पि-धा 3 U, कोशे निविश् c., कोशस्थ *a.* कृ 8 U. -ed, *a.* परिवृत, परिवेष्टित, परिक्षिप्त. 2 अवरुद्ध, सावरण, प्राकारावृत. 3 कोशस्थ, पिहित, परिच्छन्न, आवेष्टित, कोशांतर्गत. -ure, *s.* वृति *f.*, आवरणं, प्राकारः, प्राचीरं, आवेष्टनं, अवरोधकं, वरणः. 2 वाटः-टी. 3 अंतर्गतपत्रं.

Encomium, *s.* प्रशंसा, श्लाघा, स्तुति *f.*, स्तवः, स्तुतिवाक्यं, वर्णनं, गुणप्रशंसा. -Encomiast, *s.* गुणप्रशंसकः, स्तुतिपाठकः. -ic, -ical, *a.* स्तुतिमय (यी *f.*); श्लाघामय, प्रशंसाकर (री *f.*).

Encompass, *v. t.* परि-इ 2 P, व्याप् 5 P, परिच्छद् 10, परिक्षिप् 6 P, संवल् 1 A, संवलयति (D.): *See* **Encircle.** -ment, *s.* परिवेष्टनं, परिगमः, परिवृति *f.*

Encore, *v. t.* प्रशंसासूचनार्थं पुनः इति उत्कुश् 1 P, पुनरुक्ततां मार्ग् 10 A.

Encounter, *v. t.* अभि-इ 2 P, -गम् 1 P, समागम्, मिल् 6 P, समा-इ, समासद् c., संमुखं-अभिमुखं-गम्, संमुखीभू. 2 विग्रह् 9 P, प्रतियुध् 4 A, संघट्ट् 1 A, समाहन् 2 P. 3 प्राप् 5 P, अभिभू pass.; 'e. difficulties' आपदं प्राप्नुवंति, आपदाभिभूयंते; 'he e-ed many dangers' तस्य बहूनि संकटान्यापतितानि. —*s.* समागमः, संगः-गमः, संमिलनं, दर्शनं, समासादनं. 2 विग्रहः, संग्रामः, समाघातः, संपरायः, संप्रहारः, सं-आ-पातः; *See* **Battle;** 'close e.' संघट्टः.

Encourage, *v. t.* प्रोत्सह् c., आ-समा-श्वस् c., प्रेर् c., प्रवृत् c., उत्तिज् c., आशां बंध् c. -er, *s.* आश्वासकः, प्रवर्तकः. -ing, *a.* आश्वासिन्, प्रोत्साहक, उत्तेजक (की *f.*), आश्वासक. -ment, *s.* प्रोत्साहनं, आश्वासनं, उत्तेजनं, धैर्यवर्धनं. 2 साहाय्यं, अनुग्रहः, उपकारः, आनुकूल्यं, आश्रयः, अभ्युपपत्ति *f.*

Encroach, *v. t.* आक्रम् 1 U, 4 P, अन्यायतः ग्रह् 9 P अन्यायेन प्रविश् 6 P. अधर्मतः ग्रह् or आत्मसात्कृ. -ment, *s.* अन्यायेन ग्रहणं, अधर्मतः आक्रमणं-ग्रहणं.

Encrust, *v. t.* घनपटलेन आच्छद् 10 or परिवेष्ट् 1 A or c., बहिर्भागे घनीकृ 8 U. -ed, *a.* सपटल, घनीभूत. -ation, *s.* बाह्यपटलं, बहिरावेष्टनं.

Encumber, *v. t.* प्रतिबंध् 9 P, उप-नि-रुध् 7 U भारेण आक्रम् 1 U, 4 P or क्लिश् 9 P, भाराक्रांत *a.* कृ 8 U; 'e-ed with debt' ऋणभारग्रस्त -ed, *a.* भाराक्रांत, भारग्रस्त. 2 बाधित, उपरुद्ध, प्रतिबद्ध, &c. -Encumbrance, *s.* भारः, भारभूतः. 2 प्रतिबंधः, उपरोधः, प्रत्यूहः, विघ्नः, अंतरायः. 3 ऋणभारः.

Encyclical, *a.* वर्तुल, चाक्रेय (यी *f.*); 'e. letter' चक्रं, बहुसाधारणपत्रं.

Encyclopædia, *s.* विद्याचक्र-कोषः; 'e. of learning' विद्यासागरः, ज्ञानोदधिः.

End, *s.* अंतः, प्रांतः, पर्यंतः-तं, अवधिः, सीमा, अंतरं. 2 अत्ययः, शेषः-षं, क्षयः, अवसादः, अंतः, अवसानं, पर्यवसानं, परिणामः; 'pleasing at the e.' परिणामरमणीय; 'of good e.' सुखोदर्क. 3 समाप्ति-निष्पत्ति-निर्वृत्ति-सिद्धि *f.* 4 विरामः, विच्छेदः, निवृत्ति *f.*, उपशमः. 5 निधनं, मरणं, अत्ययः, विनाशः, देहक्षयः. 6 फलं, परिणामः, उत्तरफलं. 7 आशयः, हेतुः, अभिप्रायः, अर्थः, उद्देशः, कार्यं, तात्पर्यं; 'to no e.' निरर्थक; 'e. of the world' कल्पांतः, प्रलयः, प्रत्यवहारः, क्षयः, संवर्तः; 'put an e. to' समाप् c., त्यज् 1 P, उत्सृज् 6 P, नश् c.; 'e of a garment' अंचलः, दशाः pl.; hear my speech to the e.' शृणु मे वाच-

शेषं वचः (M. 4.). —v. t. समाप् c., अवसो 4 P, सं-निः-पद् c., निर्वृत् c., संपूर् 10; oft. by अंत in comp. —v. i. अवसो pass., समाप्-निष्पद् pass.; शम् 4 P, विरम् 1 P, विगम् 1 P, अपया 2 U, निष्क्रम् 1 U, 4 P; oft. by (s.) above; 'it will e. in good' कल्याणोदर्कं भविष्यति (U. 4); 'roots e. ing in vowels' अजंता धातवः; सागरांता मही, &c. —ing, s. अंतः, अंत्यं अक्षरं. —a. अंत्य. —less, a. अनंत, अपार, अशेष, निर्मर्याद, निरवधि. 2 निरंतर, अविरत, अविच्छिन्न, सतत, अतिदीर्घ, अनवरत. —lessly, adv. अत्यंतं, अविरतं, सततं, &c. —lessness, s. आनंत्यं, अविरति f., अविच्छेदः, &c.

Endanger, v. t. संशये पत् c. or क्षिप् 6 P, संशयस्थ-संदेहदोलास्थ -a. कृ 8 U: See **Danger.**

Endear, v. t. प्रिय a. or प्रीतिपात्रं कृ 8 U; 'e. oneself' प्रीतिपात्र-भाजनं-भू. —ing, a. प्रियकर (री f.), प्रीतिकर. —ment, s. प्रीति f., प्रणयः, प्रेमन् m., n., प्रेम-स्नेह-कारणं-हेतुः; 'a word of e.' प्रियवाक्यं. 2 विलासः, विभ्रमः. हावः, शृंगारचेष्टा.

Endeavour, v. i. प्र-,यत् 1 A, घट् 1 A, उद्यम् 1 P: 'e. ing for others' परार्थघटकाः, परार्थमुद्यमभृतः. —s. व्यापारः, व्यवसायः, प्रयत्नः, आयासः; See **Attempt.**

Endemic, a. स्थानिक (व्याधिः).

Endishabille, a. अकृत-नेपथ्य-वेश.

Endorse, v. t. पृष्ठे (स्वनाम) लिख् 6 P; लेखस्य पृष्ठेऽभिलिखेद्दत्वा दत्वा धनं ऋणी (Y. II.). 2 दृढयति (D.), दृढीकृ, प्रमाणीकृ 8 U.

Endow, v. t. वृत्तिं दा 3 U, प्रतिष्ठा c. (प्रतिष्ठापयति). 2 युज् 10: संपन्न a. कृ 8 U; oft. by 'e. ed.' —ed, a. युक्त, संपन्न, विशिष्ट, अन्वित, उपेत, उपपन्न, शालिन्, gen. in comp. or with instr. —ment, s. वृत्ति f., वृत्ति-शुल्क-दानं; प्रतिष्ठा; अग्रहारदानं. 2 निर्बंधः. 3 गुणः, शक्ति f.; 'intellectual e. s' बुद्धिगुणाः, मतिविभवः-प्रकर्षः.

Endue, See **Endow.**

Endure, v. t. सह् 1 A, विषह्, क्षम् 1 A. तिज् desid. (तितिक्षते), मृष् 4 P, 10. 2 भुज् 7 A. धृ 10. 3 शक् 5 P, पृ 10. उत्सह्; See **Able.** —v. i. स्था 1 P. चिरं स्था; 'as long as the sun and the moon e.' यावच्चंद्रदिवाकरौ. —ance, s. सहिष्णुता, सहनशीलता. 2 क्षमा, तितिक्षा, सहनं, मर्षणं, क्षांति f. 3 धैर्यं, उत्साहः; 'e. of austerities' दमः. 4 संस्थिति f., स्थायित्वं. —er, s. सोढृ m., क्षंतृ m., सहः in comp. —ing, a. स्थायिन्, चिरस्थायिन्, अविसर्गिन्, आयत; 'miseries are of an e. character' आयतस्वभावानि दुःखानि (Ka. 175).

2 सहिष्णु, सहनशील, तितिक्षु, सहन, क्षमिन्.

Enemy, s. शत्रुः, अरिः, रिपुः, वैरिन् m., अरातिः, द्विष् m., प्रति-वि-पक्षः, परिपंथिन् m., अमित्रः, द्वेष्टृ m., अपकर्तृ m., सपत्नः, दुर्हृद् m., परः, प्रत्यर्थिन् m., द्विषत् n., द्वेषणः, अहितः, शात्रवः, अभियातिन् m.; 'an e. in the rear' पार्ष्णिग्राहः. —Inimical, a. विरुद्ध, शात्रव (वी f.), द्वेषिन्, वैरिन्, अहित, विपक्ष, विरोधिन्, अननुकूल. —ly, adv. रिपुवत्, सवैरं, द्रोहबुद्ध्या. —Enmity, s. वैरं, शत्रुता, शत्रुभावः, विद्वेषः, विपक्षता, सापत्न्यं, द्वंद्वभावः, विरोधः.

Energy, s. शक्ति f., प्रभावः, वीर्यं, तेजस् n., सत्त्वं, पौरुषं, उत्साहः, उद्योगः, अतंद्रिता, उद्यमः, व्यवसायः, कर्मोद्योगः. —Energetic, a. उद्योगिन्, उद्यमिन्, व्यवसायिन्, सोत्साह, कर्मोद्युक्त, सोद्योग, अनलस, अतंद्रित, उत्साहवत्. 2 वीर्यवत्, तेजस्विन्. —ally, adv. सोत्साहं, सोद्योगं, सयत्नं, शक्त्या.

Enervate, Enfeeble, v. t. दुर्बलीकृ 8 U, क्षीणीकृ, तेजः-शक्ति-हृ 1 P. —ed, a. क्षीणशक्ति, हतवीर्य, क्षीणबल, दुर्बल, शिथिलबल. —ion, —ing, s. वीर्यक्षयः. शक्ति-तेजो-हानि f., क्षीणता, अपचयः, क्षामता.

Enfold, v. t. गुंठ् 10. वेष्ट् 10.

Enforce, v. t. बलात् कृ c.; See **Compel;** 'e.-ed to pay' दापित. 2 दृढीकृ 8 U, दृढयति (D.), सबल a. कृ, स्थिरीकृ. 3 (Rules &c.) प्रवृत् c., बलेन प्रणी 1 P or निर्वह् c. —ment, s. (बलेन) प्रवर्तनं, प्रणयनं. 2 दृढीकरणं; दृढप्रमाणं.

Enfranchise, v. t. बंधनात् मुच् 6 P or c. or मोक्ष् 10. 2 स्वतंत्रीकृ 8 U, स्वतंत्राधिकारं दा 3 U. —ment, s. दास्यविमोचनं, बंधनमोक्षः. 2 पौराधिकारदानं.

Engage, v. t. आकृष् 1 P, अनुरंज् c., आराध् c., हृ 1 P. 2 व्या-पृ c., प्रयुज् 10, विनियुज्. 3 नियुज्, अधिकृ 8 U, वृ 10 (वरयति). 4 (A word) प्रतिश्रु 5 U, प्रतिज्ञा 9 U, नियमपत्रेण (आत्मानं) बंध् 9 P. 5 सं-प्रति-युध् 4 A, आक्रम् 1 U, 4 P, समाहन् 2 P. 6 वाचा दा 3 U or प्रतिश्रु; विवाहसंबंधं- वाङ्निश्चयं- कृ. —v. i. (To be e. ed in) व्यापृ 6 A, निरत-आसक्त -a. भू 1 P. प्रवृत् 1 A. (with loc.): सेव् 1 A, आस्था 1 A (with acc.). 2 संयुध्, युद्धं कृ. 3 आरभ् 1 A, व्यव-सो 4 P, उपक्रम् 1 A. 4 प्रति-ज्ञा, प्रति-श्रु, परिपण् 1 A. अभ्युपगम् 4 P. —ed, a. व्यापृत, सव्यापार, प्रवृत्त, कार्यनिष्ठ, कर्मोद्युक्त, उद्यमासक्त; gen. ex. by पर, निरत, मग्न, आसक्त, तत्पर, परायण, in comp.; 'e. in contemplation' ध्यानपर-निरत, &c. 2 प्रति-ज्ञात-श्रुत, संविदित, कृतसंकेत; 'e. to be married' वाग्दत्त, प्रतिज्ञाविवाहित. —ing, a. मनोहर

हृदयग्राहिन्, हारिन्, आकर्षक, मोहिन्; चित्ताकर्षिन्. **-ingly,** *adv.* मनोहारितया. **-ment,** *s.* व्यवसायः, प्रवृत्ति *f.*, व्यवहारः, कर्मन् *n.*, व्यापारः, कार्यं. 2 युद्धं, संग्रामः, रणाभियोगः; *See* **Battle.** 3 प्रतिज्ञा, संकेतः, संविद् *f.*, नियमः, समयः, पणः, व्यवस्था, अभ्युपगमः, प्रतिश्रुतं वचः; 'keep an e.' समयं पा c. (पालयति) or अनुरुध् 4 A or अनुवृत् 1 A: 'let us keep our e.' सामयिका भवामः (M. 1); 'has kept his e.' स्थितप्रतिज्ञः; 'marriage e.' वाग्निश्चयः, विवाहप्रतिज्ञा; 'I have many e.s to-day' मया बहवः संकेताः-समयाः अद्य पालनीयाः.

Engender, *v. t.* उत्पद् c., प्रसू 2 A. उद्-भू c., जन् c.: *See* **Beget.**

Engine, *s.* यंत्रं, उपकरणं, साधनं; 'military e.' युद्धोपकरणं.

Engineer, *s.* यंत्रकारः, यंत्रकलाभिज्ञः, वास्तुविद्याविशारदः. **-ing,** *s.* यंत्रकारस्य व्यापारः. 2 वास्तुविद्या, यंत्रशास्त्रं.

Engird, Engirdle, *See* **Encircle.**

Engraft, *v. t.* (अन्यस्थानादानीय) निविश् c., संयुज् 10, संलग्नीकृ 8 U.

Engrasp, *v. t.* ग्रह् 9 P, धृ 1 P, 10.

Engrave, *v. t.* मुद्र् 10. उत्कॄ 6 P, तक्ष् 1, 5 P, त्वक्ष् 1 P; 'with the name e.ed on the ring' मणिबंधनोत्कीर्णनामधेयं (S. 6). **-er,** *s.* तक्षृ-त्वष्टृ *m.*, तक्षन् *m.* **-ing,** *s.* तक्षणं. 2 मुद्रा.

Engross, *v. t.* अभिभू 1 P, एकाग्र-अनन्यविषय- *a.* कृ, आकुलीकृ 8 U; better by 'e.ed'. 2 सर्वं ग्रह् 9 P, पूर्वं ग्रह् or क्री 9 U, साकल्येन आत्मसात्कृ. **-ed,** *a.* निविष्ट, अभिनिविष्ट, आसक्त, अनन्यविषय, एकाग्र; ex. by परायण, निमग्न, पर, in comp.; 'e. in grief' शोकपरायण. **-er,** *s.* पूर्वक्रेतृ *m.*

Engulf, *v. t.* जलावर्ते निक्षिप् 6 P, आवर्तेन ग्रस् 1 A.

Enhance, *v. t.* वृध् c., उपचि 5 U, अधिक *a.* कृ 8 U. **-ment,** *s.* वृद्धि *f.*, वर्धनं, उपचयः.

Enigma, *s.* प्रहेलिका, गूढप्रश्नः, प्रश्नदूती, प्रवह्लिका. **-Enigmatical,** *a.* गूढार्थ, अस्पष्टार्थ, दुर्ज्ञेय, अभिन्नार्थ, वक्र, गूढ. **-ly,** *adv.* गूढं, अस्पष्टं, वक्रोक्त्या, अभिन्नार्थं.

Enjoin, *v. t.* शास् 2 P, आदिश् 6 P, विधा 3 U; 'e.ed by Scriptures' शास्त्रविहित. 2 नियुज् 7 A, 10, उपदिश्; प्र-, चुद् 10.

Enjoy, *v. t.* उप-सं-भुज् 7 U, अनुभू 1 P, आस्वाद् 1 A, अश् 5 A; निर्विश् 6 P; (निर्विश्यतां सुंदरि यौवनश्रीः R. vi. 50.). 2 (Be delighted by) मुद् 1 A, रम् 1 A, नंद् 1 P, (अन्येषामभ्युदयेन मोदस्व, &c.); 'let us e. this festive holiday in playing' अनध्यायमहोत्सवं खेलंतः संभावयामः (U. 4). 3 सुखेन उपभुज् or सेव् 1 A. **-able,** *a.* भोग्य, उपभोग्य. 2 सुभग, रम्य, रमणीय, सुखद, मनोरम, कमनीय. **-ment,** *s.* उप-सं-भोगः, अनुभवः, आस्वादः-दनं, निर्वेशः, सुखास्वादः; 'objects of e.' विषयाः. 2 सुखं, आनंदः, हर्षः, संतोषः, प्रमोदः, सौख्यं.

Enkindle, *See* **Kindle.**

Enlarge, *v. t.* विस्तॄ c. वि-प्र-तन् 8 U, प्र-सृ c., प्रथ् 10, विशालीकृ 8 U. 2 वृध् c., एध् c., आप्यै c., वृद्धिं नी 1 P, स्फाय् c. (स्फावयति). **-v. i.** वृध् 1 A, विस्तॄ-उपचि-वितन् pass., स्फाय् 1 A, प्यै 1 A, प्ररुह् 1 P, वृद्धिं इ 2 P. 2 (upon) प्रपंचयति (D.), विस्तरेण-सविस्तरं-वद् 1 P or अभिधा 3 U or वर्ण् 10. **-ment,** *s.* वृद्धि *f.*, विस्तारः, वर्धनं, स्फीति *f.*, बृहणं. 2 विपुलता, प्रपंचः, वाग्विस्तरः.

Enlighten, *v. t.* (ज्ञानेन) वि-प्र-काश् c., उद्भास् c., दीप् c., प्रति-प्र-बुध् c., उपदिश् 6 P, विमलीकृ 8 U, संस्कृ, व्युत्पद् c. **-ed,** *a.* प्रतिबुद्ध, संस्कृतचित्त, व्युत्पन्न, प्राप्तज्ञान, ज्ञानोद्दीपितचित्त, प्रतिबोधवत्. **-ment,** *s.* ज्ञानोद्दीपनं. प्रबोधः-धनं; संस्कारः, प्रवृत्ति *f.*, ज्ञानागमः, चित्तप्रबोधनं.

Enlist, *v. t.* नामावलिपत्रे नाम लिख् 6 P or आरुह् c. (रोपयति). 2 (Soldiers) सैन्यमध्ये आरुह् c., युद्धकर्मणि व्या-पृ c. or प्रवृत् c., अस्त्राणि ग्रह् c. 3 आकृष् 1 P, आत्मसात्कृ 8 U, स्वपक्षे आनी 1 P or कृष्; 'having got a certificate e.ing him among Gods' अमरगणनालेख्यमासाद्य (R. viii. 95.).

Enliven, *v. t.* हृष् c., ह्लाद् c., उल्लस् c. 2 उत्साहं जन् c. (जनयति), आश्वस् c., प्रोत्सह् c., उत्तिज् c. **-ing,** *a.* उत्साह-हर्ष-जनक.

En mass, *See* **En bloc.**

Enmesh, *v. t.* जाले-बंध्-ग्रह् 9 P.

Ennoble, *v. t.* उन्नम् c. (उन्नमयति), उत्कर्षं-उन्नतिं-नी 1 P, उत्-श्रि c., उत्कृष् 1P or c., प्रतिष्ठां प्राप् c. 2 कुलीनपदे नियुज् 7 A, 10, उच्चपदं आरुह् c. (रोपयति) or प्राप् c., संमन् c. **-ment,** *s.* उत्कर्षः, उन्नति *f.*, प्रतिष्ठा, उच्चपदावाप्ति *f.*

Ennui, *s.* ग्लानि *f.*, क्लान्ति *f.*, अवसादः; श्रमः.

Enormous, *a.* असाधारण, अतिमात्र, अलौकिक (की *f.*), अपरिमित, अत्यंत. 2 महाप्रमाण, अतिबृहत्, अतिमहत्; 'e. in body' बृहत्काय, भीम-महा-काय. 3 घोर, दारुण, अतिनिंद्य, दुष्ट, पापिष्ठ. **-ly,** *adv.* अतिमात्रं, सातिशयं, अत्यंतं, भृशं; सु-अति-pr.

-Enormity, *s.* घोरता, दारुणता, &c. 2 घोर-महा-पातकं, महापराधः, अतिपापं.

Enough, *a.* यथेष्ट, बहुल, प्रचुर, पर्याप्त. 2 समर्थ, क्षम, उचित, उपयुक्त; oft. by अलं with inf. or dat., (तस्यालमेषा क्षुधितस्य तृप्त्यै R. II. 39). **-adv.** अलं, कृतं, (with instr.); 'e. of prolixity' अलमतिविस्तरेण. 2 यथेष्टं, प्रचुरं, पर्याप्तं; 'to be e. for' क्लृप् 1 A (with dat.): 'rich e.' भूयसा वित्तवान्; with adverbs by एव or भूयसा; सम्यगेव, भूयसा सुष्ठु, &c.; 'be good e. to grant my request' मम प्रार्थनामनुमंतुं प्रसीदतु भवान्. **-s.** पर्याप्ति *f.*, प्राचुर्य, बाहुल्यं, यथेष्टत्वं; 'having e. for maintenance' अलंजीविक.

Enquire,-y, *See* **Inquire,-y.**

Enrage, *v. t.* प्रकुप् c. क्रुध् c., रुष् c., संरभ् c. (संरंभयति), कोपं-रोषं-कृ 1 P; कोपं उद्दीप् c. or इंध् 7 A. **-ed,** *a.* कुपित, क्रुद्ध, क्रुद्धमन्यु, प्रकोपित, कोपाकुल, संरब्ध, जातामर्ष; 'to be e.' क्रुध्-कुप्-रुष् 4 P (with dat.).

Enrapture, Enravish, *v. t.* अतिहर्षेण मुह् c. or जडीकृ 8 U, अतिमात्रं हृष् c. or उल्लस् c. **-ed,** *a.* हर्षजड-मोहित, संमहृष्ट, अत्युल्लासित, हर्षोन्मत्त, परमानंदित; 'to be e.' अत्यंतं हृष् 4 P, हर्षेण मुह् 4 P or जडीभू. **-ment,** *s.* हर्षोन्मादः, परमानंदः, हर्षमोहः.

Enrich, *v. t.* धनिन्-सधन-आढ्य-द्रव्यसंपन्न-*a.* कृ 8 U; समृध् c., धनं वृध् c. or आप्यै c. or स्फाय् (स्फावयति). 2 **Adorn,** q. v.

Enroll, *v. t.* **Enlist,** q. v. **-er,** *s.* नामलेखकः. **-ment,** *s.* नामलिखनं, नामारोपणं.

Enrooted, *a.* रूढ-बद्ध-मूल.

Ensanguine, *v. t.* शोणितेन लिप् 6 P.

Ensconce, *See* **Conceal.**

Enshrine, *v. t.* सुप्रतिष्ठितस्थाने निर्विश् c. or रक्ष् 1 P.

Enshroud, *v. t.* आ-,छद् 10.

Ensiform, *a.* खड्गाकार.

Ensign, *s.* पताका, ध्वजः, केतनं, केतुः, वैजयंती. 2 चिह्नं, लिंगं, लक्षणं. 3 (E.-bearer) ध्वजिन्-पताकिन्-*m.*

Ensilage, *s.* गर्तायां हरिततृणसंग्रहः.

Enslave, *v. t.* दासीकृ 8 U, (fig. also), वशीकृ; दास्ये नियुज् 7 A, 10, or बंध् 9 P. **-ment,** *s.* दास्यं, दासभावः, बंधनं.

Ensnare, *v. t.* पाशेन-जालेन-बंध् 9 P, पाशे पत् c., जालबद्ध *a.* कृ 8 U, जाले धृ 1 P, 10.

Ensue, *v. i.* समापद् 4 A, प्रवृत् 1 A, उत्पद् 4 A, जन् 4 A, सं-उत्-प्र-भू 1 P, प्रसंज् pass. 2 अनुसृ 1 P, अनु-इ 2 P, पश्चात् आगम् 1 P. **-ing,** *a.* आगामिन्, भाविन्; अनागत, उत्तरकालीन, उत्तर-पर-in comp.; 'on the e. day' परेद्युः, आगामिनि दिवसे.

Ensure, *v. t.* निश्चित *a.* कृ 8 U, स्थिरीदृढी-कृ; 'diligence will e. you speedy success' उद्यमयोगादचिरवर्तिनीं सिद्धिमवगच्छ.

Entail, *v. t.* आवह् 1 P, उत्पद् c., जन् c. (जनयति). 2 (रिक्थं) प्र-दा 3 U. **-s.** क्रमागतरिक्थं. 2 क्रमागमविधिः.

Entangle, *v.t.* संश्लिष् c., संबंध् 9P, संलग्न कृ 8 U, आकुली-संकीर्णी-कृ. 2 संबंध् 9 P, संसिध् 10; better by 'e. ed'. **-ed,** *a.* सक्त, आ-सं-सक्त, लग्न, सं-परि-लग्न, आ-सं-परि-श्लिष्ट; कुरबकशाखापरिलग्नं च वल्कलं (S. 1); शाखास्वसक्तमपि (S. 2), &c. 2 संकीर्ण, संकुल, ग्रंथिल. 3 आकुंचित, व्यावर्तित; 'e. hair' जटा, जटाजूटः; 'having e. hair' जटिल, जटावत्; 'e. in a net' जालबद्ध. **-ment,** *s.* संश्लिष्टता, जटिलत्वं, ग्रंथिलत्वं. 2 संकरः, व्यतिकरः, संकुलता.

Enter, *v.* विश् 6 P, नि-प्र-आ°; गाह् 1 A, आगम् 1 P, आया 2 P, पदं कृ 8 U or निधा 3 U; 'a thought e. ed into his head' कश्चित्संकल्पस्तस्य चेतसि प्रादुर्बभूव; 'curiosity e. ed his heart' कुतूहलेन तस्य चेतसि पदं कृतं; 'e. into conversation' भाषणविमग्न *a.* भू 1 P; 'e. into alliance' संधिं कृ; 'e. into another's views' परमतं ग्रह् 9 P, अन्यभावमनुप्रविश्, अन्यमतं स्वीकृ or अनुमन् 4 A; 'e. on a course' कार्यं आरभ् 1 A, कार्ये प्रवृत् 1 A. 2 (A name) लिख् 6 P. विनिविश् c., समारुह् c. (रोपयति). **-Entrance,** *s.* प्रवेशः-शनं, &c. 2 द्वारं *See* **Door. -Entry,** *s.* द्वारं, गमनागमनमार्गः. 2 लिखनं, पत्रारोपणं.

Enteric, *a.* अंत्रसंबंधिन्.

Enterprise, *s.* साहसं, आश्चर्यकर्मन् *n.*, अद्भुतकार्यं, दुष्करकर्मन् *n.* 2 उद्यमः, व्यवसायकार्यं, प्रवृत्ति *f.*, उद्योगः, चेष्टितं, आरंभः, व्यवसायः. 3 उत्साहः, धैर्यं. **-v. t.,** *See* **Begin. -ing,** *a.* उद्योगिन्, व्यवसायिन्, सोद्योग. 2 धीर, उत्साहिन्, सोत्साह. 3 साहसिक (की *f.*), दुष्करकार्ये प्रवर्तक.

Entertain, *v. t.* पूज् 10, संमन् c., अर्च् 1 P, 10, संवृ c., सत्कृ, आतिथ्यं कृ 8 U; 'e. with food' भोजनदानेन तृप् c. or तुष् c. 2 विनुद् c., रम् c. (रमयति), अतिथ्युत् c. 3 धृ 1 P, 10, ग्रह् 9 P; *See* **Bear;** 'e. a hope' आशां आस्था 1 U or अवलंब् 1 A; 'do not e. doubts' मा ते संशयोभूत्. **-er,** *s.* विनोदकः, सत्कारिन् *m.*, आतिथेयः. **-ment,** *s.* पूजा, सत्कारः, आतिथ्यं, अतिथिसेवा-पूजनं. 2 विनोदः-दनं. 3 उत्सवः; 'musical e.' गानोत्सवः; संभोजनं, &c

Enthral, *v. t.* दासी-वशी-कृ 8 U.

Enthrone, *v. t.* सिंहासने उपविश् c., राज्ये अभिषिच् 6 P.

Enthuse, *v. i.* उत्सह् 1 A, उन्मद् 4 P. –*v. t* causals of the above.

Enthusiasm, *s* उत्साहः, उत्कटता, औत्सुक्यं, तीक्ष्णता, व्यग्रता, चंडता, उन्मादः 2 (Religious e.) धर्मोन्मादः, भक्ति-श्रद्धा-उन्मादः, अतिश्रद्धोन्मादः. –**Enthusiast,** *s.* भक्तिव्यग्रः, श्रद्धोन्मत्तः. 2 उत्साहिन् *m.* –**ic,** –**ical,** *a.* उत्साहयत् सोत्साह; अत्यंत, उत्कट, प्रचंड, उत्सुक, व्यग्र, तीक्ष्ण, उद्युक्त; उन्मत्त; '*e* devotion निरतिशया भक्तिः, निष्ठातिरेकः. –**ically,** *adv.* अत्यनुरागेण, अत्यंतं.

Enthymeme, *s.* लुप्तावयवः पक्षः or हेतुः.

Entice, *v. t* वि-आ-कृष् 1 P, हृ 1 P, मुह् c. प्र-वि-लुभ् c दुष्कृतौ प्रवृत् c –**ment,** *s.* आकर्षणं, प्र-वि-लोभनं, मोहः, वंचनं. –**er,** –**ing,** *See* **Allurer,** –**ing.**

Entire, *a.* कृत्स्न, समग्र, अखंड, सकल, सर्व, अखिल, समस्त, संपूर्ण, निखिल, निःशेष, अशेष, अन्यून, अभिन्न, साद्यंत. 2 सरल, ऋजु, अभंग्र, अहार्य (धनादिना). –**ly,** *adv.* अखंडं, साकल्येन, अशेषं, कृत्स्नशः, सर्वतः, निखिलेन. 2 (Solely) एक in comp., एव, सर्वथा; 'dependi g e. on water' जलैकायत्त. –**ness,** –**ty,** *s* समग्रता, साकल्यं, संपूर्णता, अखंडत्वं, अन्यूनता. 2 अभेद्यता, अहार्यता, आर्जवं.

Entitle, *v. t.* नाम कृ 8 U, अभिधा 3 U. *See* **Call** 2 अधिकारं दा 3 P, अधिकृ 8 U ex. by अर्ह् 1 P. or pot pass. part 'he is e. to respect' मानमर्हति, मान्यः, पूज्यः; 'persons e.-ed to a share' अंशाधिकारिणः, अंशभाजः, अंशार्हाः; 'e. ed to praise' प्रशंसार्ह, प्रशंसापात्रं.

Entity, *s.* सत्वं, अस्तित्वं, भावः, सत्ता.

Entomb, *v. t* श्मशाने निखन् 1 P or निधा 3 U or स्था c. (स्थापयति); 'e. ed in despair' नैराश्योपहत.

Entomology, *s.* कीटकशास्त्रं.

Entourage, *s.* परिवारः.

Entrails, *s.* अंत्राणि (pl.), पुरीतत् *n.*

Entrance, *v. t.* (Put in a trance) मुह् c., मूर्च्छां प्राप् c. –**ed,** *a.* मूढ, मूर्च्छापन्न, प्रलीन. 2 उन्मत्त, हृष्ट त.

Entrap, *See* **Ensnare.**

Entreat, *v. t.* अभि-प्र-अर्थ् 10 A, अनुनी 1 P, विनयेन-सांजलि-याच् 1 A or अर्थ, प्रसद् c., सविनयं निविद् c. –**ing,** *a.* सानुनय, सविनय, सांजलि. –**y,** *s.* प्रार्थना-ना, अभ्यर्थना, याचना, विनति *f.*, अर्थिता, अनुनयः; सांजलिप्रा-

Entrench, *See* **Encroach.** 2 परिखया रक्ष् 1 P.

Entrust, *v. t.* निक्षिप् 6 P, आ-समा-रुह् c (रोपयति), निविश् c., न्यस् 4 U, न्यासीकृ 8 U (with loc.); प्रतिपद् c., दा 3 U, ऋ c. (अर्पयति) (with dat.).

Entwine, *v. t.* ग्रंथ् 9 P, उद्-ग्रंथ्, गु(गुं)फ् 6 P, विरच् 10: *See* **Encircle** also.

Enucleate, *v. t* वि-परि-शुध् c. स्पष्टीकृ 8 U.

Enumerate, *v. t.* परि-कृत् 10: परि-, संख्या 2 P कथ् 10, परि-वि-गण् 10, यथाक्रमं ख्या or निर्दिश् 6 P. –**ion,** *s.* परि-, संख्यानं, गणनं-ना, परिकीर्तनं, आख्यानं, कथनं, एकैकशः निर्देशः.

Enunciate, *v. t.* लक्षणं-स्वरूपं-कथ् or वर्ण् 10, उच्चर् c., उदीर् c., उदाहृ 1 P, कृत् 10, घुष् 10, निविद् c., विज्ञा c. (ज्ञापयति). –**ion,** *s* उच्चारणं, उदीरणं, उदाहरणं, परिसंख्यानं, प्रकीर्तनं, विज्ञापनं; स्वरूपवर्णनं-ना. –**ive,** *a* व्यापक, उच्चारक.

Enure, *See* **Inure.**

Envelop, *v. t.* अवगुंठ् 10 आ-परि-वेष्ट् 1 A or c., आ-परि-वृ 5 U or c आ-परि-सं-छद् 10, पिधा 3 U. 2 कोशे निधा or निविश् c. –*s.* कोशः-षः, आवेष्टनं, पिधानं, पुटः, आच्छादनं, अवगुंठनं. 2 प्रावारः, प्रच्छदपटः.

Envenom, *v. t.* विषेण दिह् 2 U or अंज् 7 P or लिप् 6 P, सविष *a* कृ 8 U –**ed,** *a.* सविष, विषदिग्ध, विषाक्त.

Environ, *v. t.* परिवेष्ट् 1 A or c., परिक्षिप् 6 P, *See* **Encircle.** –(**E. s**) *s.* परिसरः, उपांतः, अभ्यासः, उपपुरं, नगरोपांतः-तं.

Envoy, *s.* दूतः, संदेश-वार्ता-हरः, निसृष्टार्थः; राजप्रतिनिधिः.

Envy, *v. t.* असूयति (D.), ईर्ष्य् 1 P (with dat.), परोत्कर्षं न सह् 1 A or क्रुध् 4 P, 10, परद्रव्यं अभिलष्, 1 4 P or लुभ् 4 P; स्पर्ध् 1 A; 'I e. you your prosperity' त्वदुत्कर्षासहिष्णुरहं. 2 (In a good sense) स्पृह् 10 (with dat). –*s.* असूया, अभ्यसूया, ईर्ष्या, मात्सर्यं, मत्सरः, अक्षांति *f.*, असहिष्णुता; अमर्षणं; परधनाभिलाषः. –**able,** *a.* स्पृहणीय, आकांक्षणीय. 2 ईर्ष्यणीय, लोभ्य. –**er,** *s.* असूयकः, मत्सरिन् *m.*, ईर्ष्यिन् *m.* –**ous,** *a.* ईर्ष्यालु, सेर्ष्य, समत्सर, परोत्कर्षासहन, असूयक, मत्सरिन्, साभ्यसूय (with loc.): असहिष्णु in comp.; 'e. of other's happiness' परसुखासहिष्णु; oft ex by पुरोभाग in comp.; 'e. of each other's fame' (प्रायः समानविद्याः) परस्परयशःपुरोभागाः (M. 1). –**ously,** *adv.* सेर्ष्यं, साभ्यसूयं, समत्सरं, सासूयं.

Epaulet, *s.* स्कंधाभरणं, अंसालंकारः.

Ephemeral, *a.* क्षणभंगुर, क्षणविध्वंसिन्, क्षणिक (की *f.*). 2 ऐकाहिक (की *f.*).

Epic, *s.* वीरचरितवर्णनं, महाकाव्यं, वीरपुरुषेतिहासः.
Epicene, *a.* स्त्रीपुलिंग, साधारणलिंग.
Epicure, Epicurean, *a.* उदरपरायण; भोजनचंचु, उदरंभरि, लोलुप; विषयासक्त, इंद्रियसुखनिरत, विषयिन्. **-Epicurism,** *s.* विषयसेवा, विषयासक्ति *f.*, इंद्रियसुखानुरागः.
Epicycle, *s.* याकृचक्रं, परिधिः.
Epidemic,-al, *a.* व्यापक, सर्वत्रग, बहुजनसाधारण (णी *f.*); संचारिन्; 'e. disease' मारः-री, महामारी. **-**s. जनपदोद्ध्वंसः.
Epidermis, *s.* बाह्यत्वच् *f.*, बाह्यचर्मन् *n.*
Epiglottis, *s.* उप-प्रति-आलि-जिह्वा, घंटिका
Epigram, *s.* क्षुद्रकविता. लघुकाव्य.
Epigraph, *s.* पाषाण-शिला-लेखः.
Epilepsy, *s.* अपस्मारः. भ्रामरं. **-Epileptic,** *a.* अपस्मारिन्, भ्रामरिन्: 'an e. fit' अपस्माराक्रमः.
Epilogue, *s.* उपसंहारः.
Episcopacy, *s.* धर्माध्यक्षता, धर्माध्यक्षाधिकारः.
Episode, *s.* उपाख्यानं, उपकथा, प्रासंगिकवाक्यं, आख्यानं, कथा. **-ic,-ical,** *a.* प्रासंगिक (की *f.*), अप्रस्तुत. अप्रकृत.
Epispastic, *a.* स्फोटजनक.
Epistle, *s.* पत्रं, लेखः, लेख्यं; 'epistolary correspondence' पत्रेण संवादः.
Epitaph, *s.* मृत्युलेखः. चैत्योपलिपि स्मरणमंडनं.
Epithalamium, *s.* विवाहगीतं.
Epithem, *s.* प्रलेपः, उप-नाहः-देहः.
Epithet, *s.* विशेषणं, उपाधिः.
Epitome, *s.* संक्षेपः, सारः, संग्रहः, समाहारः. समसनं. **-ize,** *v. t.* संक्षिप् 6 P, समस् 4 U, संग्रह् 9 U, संहृ 1 P. **-izer, -ist,** *s.* संक्षेप्तृ *m.*, संग्रहकर्तृ *m.*
Epoch, *s.* कालः, युगं, अवधिः, निर्णीतकालः. 2 विशिष्टकालः. 3 शाकः, शकः.
Epode, *s.* उपगीतं-गानं.
Epopee, *See* **Epic.**
Equable, *a.* समान. निर्विकार, समचित्तवृत्तिभाव.
Equal, *a.* सम, समान, तुल्य, सदृश (शी *f.*). प्रतिम-संकाश-in comp.. (with instr. or gen. of person); *See* **Like;** 'to whom gold and a clod of earth are e.' समलोष्टकांचनः; the point of equality being in the instr. or loc. समुद्रेण समो गांभीर्ये,-र्येण; 'to consider e.' तुलया धृ 1 P. 2 अनवर. 3 समवृत्ति-चित्त, निर्विकार. 4 पर्याप्त, अलं with inf. or dat.; कृप् 1 A (with dat.); 'he is e. to the task' तत्कार्यं साधयितुमलं सः; रक्षणाय कल्पते, &c. **-**s. समानपदस्थः, तुल्यपदभाज् *m.* 2 समवयस्कः, सवयस्यः, तुल्यवयस्; oft. by (*a.*). **-**v. *t.* तुल् 10 (तुलयति), (प्रासादास्त्वां तुलयितुमलं Me. 65) समी-तुल्यी-कृ 8 U; oft. ex. by (*a.*); 'none can e. me in bravery' न कोपि शौर्येण मम समानः. **-ity,** *s.* साम्यं, समानता, तुल्यता, सादृश्यं, &c. **-ize,** *v. t.* समीकृ 8 U. तुल् 10. **-ly,** *adv.* समं, सदृशं, समानं, तुल्यं.
Equanimous, *a.* समचित्त-भाव-वृत्ति, निर्विकार. **-Equanimity,** *s.* समवृत्तिता-चित्तता, समभावः, समानवृत्ति *f.*
Equate, *v. t.* समीकृ 8 U. **-tion,** *s.* समीकरणं, साम्यं.
Equator, *s.* भूकक्षा, परिधिः, निरक्षः; 'celestial e.' व्योमकक्षा. **-ial,** *a.* निरक्ष in comp.: 'e. region' निरक्षदेशः.
Equery, *s.* मंदुरा, अश्व-वाजि शाला. 2 अश्वपालः.
Equiangular, *a.* समकोण, समास्रक.
Equestrian, *a.* अश्वीय, आश्विक (की *f.*). **-**s. आश्विकः, अश्वारोहः.
Equidistant, *a.* समानांतर.
Equilateral, *a.* समभुज.
Equilibrium, *s.* तुल्यता, समता, साम्यं. 2 तुल्यभारता, समतोलनं; समानभरत्वं; 'to be in e.' तुल्य *a.* भू, तुलया धृ pass., समानभार *a.* भू.
Equine, *a.* अश्वीय, अश्वसंबंधिन्.
Equinox, *s.* विषुवं, विषुवत् *n.*; 'the vernal e.' महाविषुवं, हरिपदं; 'the autumnal e.' विषुपदं, जलविषुवं. **-Equinoctial,** *a.* विषुवीय; 'e. line' विषुवद्वृत्तं, विषुमंडलं; 'e. point' अयनं.
Equip, *v. t.* सज्जीकृ 8 U. सर्वोपकरणानि प्र-उप-क्लृप् c. or उपपद् c. or समाहृ 1 P, उपकरणैः समायुज् 7 U, 10; 'e. with arms' सन्नह् c.; 'e. with clothes' वस्त्रैः संव्ये 1 P or भूष् 10. **-age,** *s.* उपकरणं, साधनं, संभारः, सामग्री, उपस्करः. 2 परिबर्हः, परिवारः. 3 सज्जा, परिच्छदः, सन्नाहः, सज्जना, कल्पना, आकल्पः. 4 वाहनं, विमानं, प्रवहणं. **-ment,** *s.* सज्जा, संभारः, सज्जीकरणं, साधनं.
Equipoise, *v. t.* समीकृ 8 U. तुलया धृ 1 P. **-**s. **Equilibrium,** q. v.
Equipollent, *a.* तुल्यबल-शक्ति-सामर्थ्य.
Equiponderant, *a.* समभार-तोल, तुल्यपरिमाण.
Equity, *s.* न्यायः, धर्मः, अपक्षपातः, न्याय्यता, सर्वसमता. **-able,** *a.* न्यायपरायणवर्तिन्, अपक्षपातिन्, समदर्शिन्, सर्वसमन्यायिन्. 2 न्याय्य, यथान्याय, पक्षपातरहित, सर्वसाधारण. **-ableness,** *s.* न्याय्यता; अपक्षपातः. **-ably,** *adv.* न्यायतः. यथान्यायं पक्षपातं विना.

Equivalent, *a.* सम, तुल्य ; *See* **Equal.** 2 तुल्यार्थक, समार्थ, तुल्यबल-शक्ति; तुल्य-सम-मूल्य, समार्घ. **-s.** तुल्यद्रव्यं-वस्तु *n.*, तुल्यमूल्यं वस्तु, प्रतिफलं. 2 तुल्यार्थः शब्दः, पर्यायः.

Equivocal, *a.* द्व्यर्थ, संदिग्धार्थ, वक्र, अस्पष्टार्थ, अव्यक्त. **-ly,** *adv.* वक्रोक्त्या, भंग्या, अस्पष्टं, संदिग्धार्थेन, अव्यक्तं. **-ness,** *s.* संदिग्धार्थः, द्व्यर्थता, अर्थसंदेहः, वक्रता, अस्पष्टता.

Equivocate, *v. i.* वक्रो-अस्पष्टार्थं-वद् 1 P, वाक्यभेदं कृ 8 U. **-ion,** *s.* वक्रवचनं, वक्रोक्तिf., वाक्यभेदः, वाक्छलं, अप-व्यपदेशः.

Equivoque, *s.* कूटोक्ति-अर्थापत्ति-*f.*, वक्रभणितं.

Era, *s.* कालः, शाकः, ध्रुवः कालः. 2 विशिष्टकालः.

Eradiate, *v. i.* किरणान् क्षिप्-मुच् 6 P, परिस्फुर् 6 P.

Eradicate, *v. t.* उत्-निर्-मूल् 10 ; उच्छिद् 7 P, उत्सद् c., उत्पट् 10, वि-ध्वंस् c., आमूलं उद्ह् 1 P or उत्खन् 1 P, व्यप-रुह् c. (रोपयति). **-ion,** *s.* उन्मूलनं, उच्छेदः, उत्पाटनं, व्यपरोपणं. **-or,** *s.* उन्मूलयितृ *m.*, उच्छेदिन् *m.*

Erase, *v. t.* व्या-अप-मृज् 2 P, विलुप् c., व्यामृश् 6 P. 2 उच्छिद् 7 P. विनश् c., उन्मूल् 10. **-ure,** व्यामर्शः, लोपः, उच्छेदः, विनाशः.

Ere, *prep., adv.* पूर्वं, प्राक्, (with abl.) ; 'e. this' अतः पूर्वं; 'e. long' अचिरात्-रेण; 'e. now' नातिचिरं, नातिचिरात्प्राक् ; 'e. while' किंचित्पूर्वं; *See* **Before.**

Erect, *a.* उन्नत, उच्छ्रित, अनत, ऊर्ध्व, उत्तान, अजिह्म ; gen. ex. by उत् in comp. ; 'with the neck e.' उद्ग्रीव, उत्कंधर; 'with the hair e.' पुलकित, रोमांचित. **-***v. t.* स्था c. (स्थापयति), प्रति-सं-अधि°, अधिवह् c. 2 निर्मा 3 A, रच् 10, विरच्, निबन्ध् 1 P, (निबबन्ध जयस्तंभान् R. IV. 36). 3 उत्था c., उन्नी 1 P, उच्छ्रि c., उन्नम् c. (उन्नमयति), उद्यम् c., उद्यम् 1 P, उत्क्षिप् 6 P, उद्ह् 1 P. **-ion,** *s.* प्रतिष्ठापनं, संस्थापनं. 2 निर्माणं, विरचनं. 3 उत्थापनं, उत्क्षेपः, उच्छ्रायः, उन्नमनं, उन्नति *f.*, उद्गमनं; 'e. of the hair' पुलकः, पुलकोद्गमः, रोमोद्गमः, रोमहर्षणं, रोमांचः.

Erode, *See* **Corrode.**

Erotic, *a.* कामप्रिय, कामिन्, कामुक.

Err, *v. i.* विभ्रम् 1, 4 P, अपराध् 4, 5 P, अपथं या 2 P, उन्मार्गेण वह् 1 P or प्रवृत् 1 A; स्खल् 1 P, प्रमद् 4 P, सत्पथात् भ्रंश् 1 A, 4 P or च्यु 1 A or विचल् 1 P, व्युत्क्रम् 1 U, 4 P, व्यतिचर् 1 P. **-ant,** *a.* परिभ्रमिन्, भ्रमणकारिन्. **-atic,** *a.* भ्रमणशील, अनियम, चर. **-ing,** *a.* भ्रांत, उन्मार्गप्रवृत्त, सत्पथभ्रष्ट-च्युत, उत्पथगामिन्, प्रमादिन्. **-Erroneous,** *a.* भ्रांतिमूलक, प्रामादिक (की *f.*), भ्रमात्मक ; मिथ्या-मृषा-'in comp. ;' 'e. notion' मिथ्याग्रहः. 2 अनृत, असत्य, अशुद्ध, अयथार्थ, असत्य, वितथ. **-ly,** *adv.* मिथ्या, मृषा, अयथार्थं, असत्यं, भ्रांत्या, प्रमादेन, सप्रमादं. **-Error,** *s.* भ्रमः, भ्रांति *f.*, मतिविभ्रमः, मोहः, व्यामोहः, मिथ्यामति *f.* 2 दोषः, अपराधः, प्रमादः, स्खलितं, पापं. 3 उन्मार्गगमनं, व्यतिक्रमः, उत्पथः, मार्गभ्रंशः ; 'in e.' भ्रांत, प्रमत्त, सदोष, अपराद्ध.

Errand, *s.* संदेशः, संदेशवाच् *f.*, वाचिकं ; शासनं, आदेशः. 2 दौत्यं, दूतकार्य-कर्तव्यं ; 'send on an e.' प्रतिशास् 2 P, आदिश् 6 P, दौत्येन प्रेष्-मेष् c, ; 'sending on an e.' प्रतिशासनं.

Erratum, *s.* अशुद्धं.

Errhine, *a.* नस्य, क्षुत्कर (री *f.*).

Erst, *adv.* पुरा, पूर्वं, प्राक्, पूर्वकाले.

Eruct, *v. t.* उद्वम् 1 P, उद्-गॄ 6 P. **-ation,** *s.* उद्गारः, उद्वमः-मनं.

Erudite, *a.* व्युत्पन्न, संस्कृतचित्त. पंडित, कृतविद्य, विपश्चित्. **-ion,** *s.* पांडित्यं, ज्ञानं, विद्या, व्युत्पत्ति *f.*

Erugimous, *a.* ताम्रकलंकरूप, ताम्रगुणविशिष्ट.

Erupt, *v. i.* उद्-गॄ-क्षिप्-स्फुट् 6 P. **-ion,** *s.* निःसरणं, निर्गमः, उद्भेदः, उद्गिरणं, स्फोटनं, उद्गारः, उत्क्षेपः ; 'e. on the skin' व्रणः, विस्फोटः. 2 कोठः, पिटिका, कोठोद्गमः. **-ive,** *a.* उद्भेदिन्, स्फोटनविशिष्ट.

Erysipelas, *s.* उद्वर्दः, व्रणः.

Escalade, *v. t.* लंघ् 1 A, 10, अवस्कंद् 1 P, निःश्रेण्या आरुह् 1 P. **-s.** दुर्गलंघनं. अवस्कंदः-दनं.

Escape, *v. t.* मुच्-विमुच् pass., प्र-रक्ष्-pass., (with abl.); 'e. ed death' मरणाद्विमुक्तः ; 'e. ed censure' दोषाद्विमुक्तः. 2 सं-निः-उत्-तॄ 1 P; लंघ् 1 A, 10, पारं इ-या-2 P or गम् 1 P. 3 परिहृ 1 P, त्यज् 1 P; 'it e. ed his notice' स तन्नालक्षयत् ; 'he has e. ed one danger to fall into another' (*Cf.* e. ed Scylla to fall into Charybdis) बंधनभ्रष्टो गृहकपोतः श्येनमुखे पतितः (M. 4.). **-***v. i.* अप-निः-क्रम् 1 U, 4 P, अपसृ 1 P, अपसृप् 1 P, निर्गम् 1 P, परा-इ 2 P, पलाय् 1 A, अप-या 2 P, अपधाव् 1 P, अलक्षितं-निभृतं-गम् ; 'he narrowly e. ed' कथं कथमपि मुक्तः ; 'e. ed with his life' पलायनेन जीवितं रक्षितवान्. **-s.** पलायनं, निर्गमः, अपक्रमः-

मणं, निष्क्रमः, अपसर्पणं, अपयानं. 2 निस्तारः, मुक्ति *f*., मोक्षः, त्राणं, क्षेमलाभः.

Escheat, *v. i.* राजसाद्-भू 1 P, (संतत्यभावात्) राजगामिन् *a.* भू, राजस्वतां आपद् 4 A, राजार्थं गम् 1 P. —*s.* राजसात्कृतं (क्षेत्रादि.)

Eschew, *See* **Avoid.**

Escort, *s.* परि-अनु-चराः, रक्षापुरुषाः (pl.); परिवारः, रक्षकगणः, रक्षिवर्गः ; 'send her with a good e.' सुरक्षितां तां प्रेषय. 2 रक्षणं, शरणं, रक्षा, अनुव्रजनं. —*v. t.* (रक्षार्थं) अनु-गम् 1 P, सह-इ 2 P, अनुव्रज् 1 P, प्रतिरक्ष् 1 P, (ऋषिप्रतिरक्षितां S. 4), परि-अनु-चर् 1 P.

Esculent, *a.* खाद्य, भक्षणीय. —*s.* खाद्यं, भक्ष्यं.

Escutcheon, *s.* कुलचिह्नपत्रं.

Esophagus, *s.* अन्नवाहि स्रोतस् *n.*

Esoteric, *a.* गूढ, अलौकिक (की *f.*), विशिष्ट.

Espalier, *s.* लताकुंजः, वृक्षजालं.

Especial, *a.* उत्तम, विशिष्ट, प्रधान, परम, मुख्य. 2 सविशेष, विशेष in comp., 'e. qualification' विशेषगुणः. —**ly,** *adv.* विशेषेण-षतः, प्रधानतः, मुख्यशः.

Esperanto, *s.* विश्व-भाषा-भारती.

Espionage, *s.* गूढावेक्षणं, चारवृत्ति *f.*, गूढप्रचारः. 2 चारप्रयोगः.

Esplanade, *s.* समः क्रीडाप्रदेशः, समीकृतं क्रीडास्थानं.

Espouse, *v. t.* परिग्रह् 9 P, वि-उद्-वह् 1 P, परिणी 1 P, वृ 5 U, 10 (वरयति). 2 अंगी-स्वी-कृ 8 U, परिग्रह्, उरी-उररी-कृ, अवलंब् 1 A, आश्रि 1 U. 3 रक्ष् 1 P, अनु-पा c. (पालयति), संवृध् c. 4 वाचा दा 3 U or प्रति-ज्ञा 9 U. —**al,** *s.* परिग्रहणं, उद्वाहः, परिणयनं. 2 वाग्दानं, वाङ्निश्चयः. 3 स्वीकारः, ग्रहणं, अनुपालनं; अवलंबनं, आश्रयः; 'e. of cause' पक्षपरिग्रहः-पातः, पक्षावलंबनं.

Espy, *v. t.* (दूरात्) आलोक् 1 A, 10. निरूप् 10, ईक्ष् 1 A, निर्वर्ण् 10.

Esquire, *s.* कंचुकवाहः, साक्षहनिकः. 2 श्री pr., आर्यः, श्रीमत् in comp.

Essay, *v. t.* आरभ् 1 A, परीक्ष् 1 A, उपक्रम् 1 A, व्यवसो 4 P; *See* **Attempt.** —*s.* परीक्षणं, प्रयत्नः, आरंभः, उद्योगः, उपक्रमः. 2 नि-प्र-बंधः, लेख्यं. —**ist,** *s.* निबंधलेखकः.

Essence, *s.* सारः-रं, मूलं, अधिभूतं, मूलवस्तु *n.*; 'vital e. of body' शरीरधातवः (pl.). 2 सारः, निष्कर्षः, निर्गलितार्थः, पिंडितार्थः, भावः, निष्कृष्टार्थः. 3 **Perfume,** q. v. —**Essential,** *a.* सारवत्, सारभूत, ससार. 2 आवश्यक, अत्यावश्यक, गुरु, महत् ; oft. ex. by अप-ईक्ष् 1 A; 'sprinkling of water is e. to the growth of sprouts' अंकुरवृद्धिर्जलसेकमपेक्षत एव. —*s.* तत्त्वं, मूलतत्त्वं, मूलं.

2 परमार्थः, मुख्यार्थः. 3 (E. s of judicature) व्यवहारमातृकाः. —**ly,** *adv.* अवश्यं, तत्त्वतः, सारतः.

Establish, *v. t.* सं-प्रति-स्था c. (स्थापयति), अधिष्ठा c.; 'one whose rule is newly e.-ed' अचिराधिष्ठितराज्यः (M. 1); प्रतिष्ठितं प्रकृतिषु 'well e. ed' &c. 2 उप-प्रति-पद् c., समर्थ् 10 निर्णी 1 P, स्थिरी-दृढी-प्रमाणी-कृ 8 U, सं-स्तंभ् 9 P or c., निगम् c. (गमयति), सिद्धांतयति (D.). 3 व्यव-स्था c. प्रक्लृप् c., वि-धा 3 U. —**ment,** *s.* संस्थापनं, स्थिरीकरणं. 2 प्रतिपादनं, उपपत्ति *f.*, निगमनं. 3 भृत्यादिवर्गः.

Estate, *s.* अवस्था, दशा; *See* **Condition.** 2 संपद् *f.*, धनं, रिक्थं, दायः; भूमि *f.*, विभवः, संपत्ति *f.*, द्रव्यं, वित्तं. 3 पदं, स्थानं 4 वर्गः, गणः.

Esteem, *v. t.* बहु मन् 4 A or c., संमन्, पूज् 10, आ-दृ 6 A. 2 गण् 10, वि-भू c. —*s.* बहु-सं-मानः, आदरः, पूजा, मान्यत्वं. 2 मतं, मति *f.* —**Estimable,** *a.* मान्य, पूज्य, अर्ह्य, पूजार्ह.

Estimate, *v. t.* निरूप् 10, वि-भू c., निर्णी 1 P, विगण् 10, सं-परिसं-ख्या 2 P, संकल् 10, निश्चि 5 U, अर्घ-मूल्यं-निरूप् or निर्णी. —*s.* गणना-नं, परिसंख्यानं, मूल्यनिरूपणं, अर्घगणना; 'rough e.' स्थूल-आकार-मानं. 2 मतं, 'in the popular e.' लोकमतेन. —**ion,** *s.* गणना-नं. 2 बहुमानः, मानः, आदरः, संमानः. —**or,** *s.* गणकः, संख्यातृ *m.*

Estival, *a.* निदाघ-ग्रीष्म-संबंधिन्.

Estop, *v. i.* रुध् 7 U., विहन् 2 P.

Estrange, *v. t.* अप-वि-रंज् c., विश्लिष् c., भिद् 7 P or c., विरागं उत्पद् c., स्नेहं भिद् or छिद् 7 P or विघट् c. (घटयति). 2 दूरीकृ 8 U, विच्छिद्, विश्लिष् c., वियुज् 7 A, 10. —**ed,** *a.* विरक्त, विश्लेषित, भेदित, जातविराग, निवृत्तस्नेह, अपरक्त, अपरागिन्. 2 दूरीकृत, विच्छिन्न, वियोजित. —**ment,** *s* विरक्ति *f.*, अप-वि-रागः, स्नेहनिवृत्ति *f.*, स्नेहच्छेदः-भेदः-विरामः. 2 वियोगः, विच्छेदः विरहः, विश्लेषः, दूरीभावः, पृथग्भावः.

Estuary, *s.* समुद्रवंकः, पुटभेदः.

Estuate, *v. i.* फेनायते (D.), उत्सिच् pass.

Et cætera, (&c.) Ex. by आदि, आद्य, प्रभृति in comp.; 'horses, asses, &c.' अश्वरासभादयः, गुडादि, &c.

Etch, *v. t.* लिख् 6 P, चित्र् 10.

Eternal, *a.* नित्य, शाश्वत (ती *f.*), अनंत, सनातन (नी *f.*), अनादि, अनाद्य, संतत, सतत, अनाद्यनंत, शाश्वतिक (की *f.*), निरंतर, अविनाशिन्, अमर, अनपाय, अविच्छिन्न, अक्षय. —**ly,** *adv.* नित्यं, शश्वत्, सदा, निरंतरं, अविरतं, सर्वकालं, अनंतं. —**Eternity,**

s. नित्यता, आनंत्यं, सनातनत्वं. 2 अनंतकालः.

Etesian, *See* **Annual.**

Ether, *s.* आकाशः-शं. 2 तेजोवहः, हिमद्रवः. **-Ethereal,** *a.* आकाशीय, नभस्-आकाश- in comp., वैहायस (सी *f.*). 2 तैजस (सी *f.*).

Ethics, *s.* नीतिविद्या-शास्त्रं, नीति *f.*, आचार-नीति *f.* **-Ethic, Ethical,** *a.* नीतिविषय-शास्त्रीय. **-ally,** *adv.* नीत्यनुसारेण.

Ethnic,-al, *a.* अन्य-भिन्न-देशीय.

Ethnology, *s.* नृवंशविद्या.

Etiquette, *s.* आ-उप-चारः, विनयरीति *f.*, -विधिः, सदाचाररीति *f.*, सौजन्यं, सभ्यता, शिष्टाचारः.

Etymology, *s.* व्युत्पत्ति *f.*, व्युत्पादनं, शब्द-साधनं, शब्दव्युत्पत्तिविद्या. **-ical,** *a.* व्युत्पत्तिविषय; 'e. sense' यौगिकोर्थः. **-ist,** *s.* शब्दव्युत्पत्तिकुशलः. **-ize,** *v. t.* व्युत्पद् c.

Eugenics, *s.* मनुजस्वभावोत्कर्षशास्त्रं.

Eulogy, *s.* प्रशंसा, स्तुति *f.*, स्तवः, श्लाघा, वर्णनं, गुणस्तुतिः-श्लाघा-वर्णना. **-ize,** *v. t.* प्रशंस् 1 P, स्तु 2 U; *See* **Praise.** **-istic,** *a.* स्तुतिमय (यी *f.*), प्रशंसाकर (री *f.*). **-ist,** *s.* प्रशंसकः, स्तुतिपाठकः, वंदिन् *m.*

Eunuch, *s.* छिन्नमुष्कः, हृतपुंस्त्वः. 2 वर्षवरः, स्थापत्यः, कंचुकिन् *m.*, सौविदः, सौविदल्लः.

Euphemism, *s.* मंगलभाषितं.

Euphony, *s.* सुस्वरः-शब्दः-स्वनः, सुश्लिष्टस्वरत्वं, अकर्कशता. 2 संयोगः, संधिः. **-ic,-ious,** *a.* सुस्वर, सुश्राव्य, सुखश्रव, श्रुतिसुख, अकर्कश; सुश्लिष्टस्वन.

Euphorbia, *s.* समंतदुग्धा, सीहुंडः, वज्रः, स्नुह् *f.*, स्नुही, गुडा.

Euthanasia, *s.* अनायासेन-यातनाशून्य *a.* मरणं or मृत्युः.

Evacuate, *v. t.* परित्यज् 1 P, वि-हा 3 P, उत्-वि-सृज् 6 P. 2 रिच् 7 P, शून्यीकृ 8 U; 'e. bowels' शुध् c., मलशुद्धिं कृ 8 U. **-ion,** *s.* परित्यागः, उत्सर्गः. 2 (of bowels) मलशुद्धि *f.*, मलोत्सर्गः. मलोत्सारः. उच्चारः, विरेचनं.

Evade, *v. t.* शाठ्येन परि-हृ 1 P, वक्रोक्त्या परिहृ, अप-लप् 1 P, अप-नि-हृ 2 P, अप-व्यप-दिश् 6 P. **-v.** *i.* शाठ्येन पलाय् 1 A or अपसृप् 1 P or अपधाव् 1 P. व्यपदेशं कृ 8 U, वाक्छलं कृ. **-Evasion,** *s.* अप-व्यप-देशः, छद्मन् *n.*, छलं, कपटं. निह्नवः, छलेन परिहरणं. 2 वक्रोक्ति *f.*. वाक्छलं, अपलापः, कपटवचनं, कैतवोक्ति *f.* 3 **Escape,** q. v. **-Evasive,** *a.* सकपट-छलित, छलान्वित. व्यपदेशिन्, अपह्नवकारिन्, 2 वक्र, कुटिल, जिह्म; 'e. answer' वक्रोत्तरं; 'when he made e. replies' यदा वाक्य-भेदान् बहुलकथयत् (Mu. 2). **-ly,** *adv.* सनिह्नवं, वाक्छलेन, वक्रोक्त्या, प्रस्तुतं परिहृत्य.

Evaluate, *v. t.* मूल्यं निर्णी 1 P.

Evanescent, *a.* क्षणिक, क्षणभंगुर, अशाश्वत (ती *f.*). 2 अदृश्य, परोक्ष, अंतर्हित, अप्रत्यक्ष.

Evaporate, *v. i.* बाष्पीभू 1 P, बाष्परूपेण उद्गम् 1 P or नश् 4 P, बाष्पायते (D.), आतपेन शुष् 4 P. 2 (fig.) विनश्, विलि 4 A, अंतर्धा pass., वि-द्रु 1 P. **-v. t.** बाष्पीकृ 8 U, आतपेन शुष् c., उच्छुष् c., बाष्परूपेण नश् c. or उद्गम् c. (गमयति). **-ed,** *a.* आतपशुष्क, शोषितरस. **-ion,** *s.* बाष्पीभवनं-करणं, बाष्पभावः, शोषणं.

Eve, *a.* पूर्वप्रदोषः. 2 **Evening,** q. v.: 'to be on the e. of taking place' उपस्था 1 P, प्रत्यासद् 1 P; *See* **Approach.**

Even, *a.* सम (in all senses): 'e. ground' समप्रदेशः-स्थलं-पाटः-भूमि *f.*: 'e.-handed' समक्रिय, समदर्शिन्, 'e.-minded' समचित्त-भाव, समवृत्ति. 2 समरेख, अवक्र, ऋजु. **-v. t.** समीकृ 8 U. **-adv.** अपि; 'e. though' 'e. if' यद्यपि: 'e. now' अद्यापि; 'e. so' एवमेव, एवं, तथैव, अथ किं; 'e. as' यथा, यथैव. **-ly,** *adv.* समं, तुल्यं, सम, तुल्य in comp. **-ness,** *s.* समता, साम्यं, तुल्यता, एकरूपता, निर्विकारता, &c.

Even, Evening, *s.* संध्या, संध्यासमयः, सायंकालः, वि-वै-कालः, दिनावसानं, प्रदोषः, रजनीमुखं, सायाह्नः; 'in the e.' सायं; 'good e. to you' शुभस्ते प्रदोषः (भूयात्). **-a.** सायंतन (नी *f.*), प्रादोषिक (की *f.*), वैकालिक (की *f.*), सायंकालीन.

Event, *s.* वृत्तं, व्यतिकरः, वृत्तांतः, घटना. संभवः, संगतं; 'in the e. of' यदि, चेत्. 2 परिणामः, फलं, अनुवृत्तं, उदर्कः, उत्तरं फलं. **-ful,** *a.* विख्यात, बहुवृत्तविशिष्ट. **-ual,** *a.* अंतिम, अंत्य. 2 आनुषंगिक (की *f.*), अनुवर्तिन्, अनुसारिन्. **-ually,** *adv.* अवशेषे, अंते, अंततः.

Ever, *adv.* कदा-चन-चित्, कदापि; कर्हिचित्, जातु; 'not e.' न कदाचन, न जातु, &c. 2 नित्यं, अहर्निशं; सदा, सर्वदा; 'for e.' शश्वत्, निरंतरं; अजस्रं, शाश्वतीः समाः; oft. by एकांत, अत्यंत in comp., 'disappeared for e.' अत्यंतविलुप्तदर्शन; 'lost for e.' एकांतनष्ट, 'gone for e.' अत्यंतविलुप्तं गत. अत्यंतगत; 'e. more' पुनः, इतः परं; 'e. and anon' वारंवारं. काले काले. मुहुर्मुहुः, मुहुः; 'e. since' यतः प्रभृति: '...

little ' मनाक्-ईषत्-किंचित्-किंचित्-अपि. With adj. ex. by नित्य, सदा, &c. in comp.; 'e. blooming' नित्यपुष्प; 'e. green' सततहरित, अम्लानपर्ण; 'e. lasting' नित्यस्थायिन्, नित्य, अकल्प, अमर; *See* **Eternal**; 'e. moving' सदा-नित्य-गति.

Evert, *v. t.* विपर्यस् 4 U, विनश् c.

Every, *a.* Ex. by प्रति-अनु-in comp.; 'e. day' प्रतिदिवसं; प्रतिवर्षं, अनुदिनं, &c., oft. by repeating the word; 'in e. place' स्थाने स्थाने; दिवसे दिवसे 'e. day' &c.; 'at e. discussion' वादे वादे. 2 सर्व, विश्व, सकल; *See* **Each**; 'knowing e. thing' सर्वज्ञः; 'suffering e. thing' सर्वसहा (पृथ्वी); 'e. one' 'e. body' सर्वः, सर्वजनः, प्रत्येकः, एकैकः; एकैकशः, पृथक् पृथक्; 'e.-day' (*a.*) प्रात्यहिक (की *f.*); 'e. thing' सर्वं; 'e. other' एकैकं परित्यज्य अन्य-अपर; 'in e. way' सर्वथा; 'e. where' विष्वक्, सर्वतः, सर्वत्र, यत्र तत्र; 'e. time' यदा यदा; 'on e. side' सर्वतः, विश्वतः, समंततः.

Evict, *v. t.* निःसृ c., निराकृ 8 U. बहिष्कृ, अधिकारात्-स्वत्वात्-भ्रंश् c. or च्यु c.

Evidence, *s.* साक्ष्यं, प्रमाणं, प्रामाण्यं, निदर्शनं; 'written e.' लेखप्रमाणं, साधनपत्रं; 'ocular e.' प्रत्यक्षप्रमाणं, चाक्षुषज्ञानं. —*v. t.* प्रमाणीकृ 8 U, प्रमाणेन साध् c. or वि-भू c. or उप-पद् c.

Evident, *a.* स्पष्ट, सुस्पष्ट, स्फुट, परिस्फुट, व्यक्त, विशद, प्रकाश, प्रत्यक्ष, प्रकट; 'make e.' प्र-काश् c., आविष्कृ 8 U, स्पष्टीकृ, वि-वृ 5 U, विशदीकृ; 'to be e.' स्पष्टीभू 1 P, &c. **-ly,** *adv.* स्पष्टं, स्फुटं, व्यक्तं, प्रत्यक्षं, नाम, oft. with एव.

Evil, *a.* दुष्ट, पाप, खल, कुत्सित, असाधु, निंद्य, अधम, पापिन्, असत्, गर्ह्य, गर्हित, वाच्य; gen. ex. by दुर्, कु, अप, असत्, पाप in comp.: 'e. intentioned' पापाशय, दुर्बुद्धि; 'e. passions' दुर्विकाराः; 'e. eye' कुदृष्टि *f.*, पापदृष्टि *f.*; 'e. course' कुपथः-मार्गः, असत्पथः; 'e.-conducted' दुराचार, अपकर्मन्, दुर्वृत्त; 'e. doer' दुर्जनः, कुकर्मन् *m.*; पापकर्मन् *m*, दुष्कृतिन् *m.*, पापकृत् *m.*; 'e.-minded' दुरात्मन्, पापमति-बुद्धि, दुष्टमति, कुमति, दुर्मति, दुर्बुद्धि, पापाशय; 'good or e. acts' शुभाशुभकर्माणि; 'e. speaking' दुरालापः, पिशुनवाक्यं; 'e.-tongued' दुर्मुख, मुखर, अबद्धमुख, कद्वद. —*s.* अनिष्टं, अहितं, अशुभं, अपायः, अभद्रं, अरिष्टं, दुःखं. 2 दुर्गति *f.*, दुरवस्था, व्यसनं, आ-वि-पद् *f.*, कष्टं, अत्याहितं. 3 अपकारः, अपायः, हिंसा.

अर्ति-ति *f.*; 4 पापं, पापाचरितं दुष्कर्मन् *n.*, कुकृत्यं, अधर्मः, दुष्कृतं, दौरात्म्यं, दोषः, दुराचारः, दुष्कृति *f.*; 'Oh! An e. has befallen!' अब्रह्मण्यं, अत्याहितं, हा धिक्, कष्टं.

Evince, *v. t.* निर्दिश् 6 P, प्रकाश् c., सूच् 10, दृश् c., स्पष्टी-व्यक्ती-प्रकटी-कृ 8 U, व्यंज् 7 P or c., द्युत् c. **-ibly,** *adv.* स्पष्टं, असंशयं, व्यक्तं. **-ive,** *a.* दर्शक, सूचक, द्योतक.

Eviscerate, *a.* निरंत्रीकृ 8 U.

Evitable, *a.* परिहार्य, हेय, वर्जनीय, अनावश्यक (की *f.*), परिहरणीय.

Evoke, *v. t.* आ-ह्वे 1 P, आ-समा-कृष् 1 P. 2 उत्पद् c., जन् c. (जनयति), प्र-बुध् c., प्रोत्सह् c., उत्तिज् c.; 'his speech e.ed laughter' तस्य वचः प्रहासाय बभूव, उपहासास्पदं जातं. **-Evocation,** *s.* आह्वानं. 2 **Appeal,** q. v.

Evolve, *v. t.* वि-वृ 5 U, उद्भिद् c. 2 वि-स्तॄ c., प्र-सृ c., वितन् 8 U. **-Evolution,** *s.* उद्भेदः, विवरणं. 2 विस्तारः-रणं, प्रसारणं. 3 परंपरा, श्रेणी. 4 मूललाभः. 5 परिणामः; 'theory of e.' परिणामवादः.

Evulsion, *s.* उत्पाटनं, उत्कर्षणं, अवलुंचनं.

Ewe, *s.* मेषी, एडका, उरणी, अविला; 'e.'s milk' अविसोढं, अविदूसं.

Ewer, *s.* कमंडलुः, कुंभः, उदकपात्रं.

Exacerbate, *v. t.* प्र-कुप् c. उत्तिज् c., क्रोधं उद्दीप् c.; *See* **Enrage. -ion,** *s.* प्रकोपणं-नं, क्रोधोद्दीपनं.

Exact, *s.* यथार्थ, यथातथ, ऋत, सत्य. 2 शुचि, निर्दोष, शुद्ध. 3 अवहित, अप्रमत्त; oft. by विशेष in comp.; स्थलविशेषः, नरविशेषः 'e. place', 'e. man &c.' 4 सूक्ष्म, विशिष्ट. 5 निर्विशेष, समान. —*v. t.* बलेन ग्रह् 9 U or आदा 3 A, बलाद् ग्रह् or निष्कृष् 1 P or आ-हृ c., दा c. (दापयति); oft. by causal. 2 बाध् 1 A, अर्द् c., उपपीड् 10. **-ion,** *s.* बलाद् ग्रहणं or आदानं, निष्कर्षः, दापनं. 2 उपद्रवः, विप्लवः, बाधाधनं, उपपीडा. **-ly,** *adv.* यथार्थतः, यथावत्, यथातथं, तत्त्वतः, सम्यक्, सत्यं, सूक्ष्मतया. 2 नाधिकं, न न्यूनं; oft. by एव; 'e. so' एवमेव, अथ किं, तथैव; 'they two are e. alike' नास्ति किमपि तयोरंतरं. **-ness,** *s.* याथार्थ्यं, सत्यता, तत्त्वता. 2 सूक्ष्मता. 3 अवधानं, अप्रमादः.

Exaggerate, *v. t.* अतिशयेन-अत्युक्त्या वर्ण् 10 or कथ् 10; संवृध् c. (Mr. 9), विस्तॄ c. **-ion,** *s.* अत्युक्ति *f.*, अतिशयोक्ति *f.*, अतिवर्णनं, वागुपचयः, संवर्धनं.

Exalt, *v. t.* उन्नम् c. (नमयति), नी 1 P or प्राप् c., उन्नी 1 P, उच्छ्रि c., उत्कृष् 1 P; उच्चपदं, प्राप् c. or अधिरुह् c. (रोपयति), उत्कृष्टपदे नियुज् 7 A, 10. **-ation**

s. उन्नति *f.*, उच्छ्रायः, उन्नमनं, उत्कर्षः, उच्चपदारोपणं; 'self e.' आत्मोत्कर्षः. **-ed,** *a.* उन्नत, उच्छ्रित, उत्कृष्ट, परम, उच्चैः; 'e. place' उच्चैःपदं; 'e. rank' गौरवपदं; *See* **Elevate.**

Examine, *v. t.* परीक्ष् 1 A, निरूप् 10, अनुसंधा 3 U, विचर् c., विमृश् 6 P. अवेक्ष्, आ-पर्या-लोच् 10. **2** निर्णी 1 P, निश्चि 5 U, परिच्छिद् 7 P. **3** अनुयुज् 7 A, प्रच्छ् 6 P: मृग 10 A, अन्विष् 4 P, चर्चां कृ 8 U, ज्ञा desid. (जिज्ञासते). **4** निरीक्ष्, समीक्ष्, परीक्ष्, निरूप्, दृश् 1 P, आ-अव-लोक् 1 A, 10. **-ation,** *s.* परीक्षा-क्षणं, विचारः-रणं-णा, निरूपणं, अनुसंधानं, अनुयोगः, प्रश्नः. **2** निरीक्षणं, आलोचनं, संदर्शनं, अवेक्षा; 'judicial e.' व्यवहारदर्शनं. **-er,** *s.* परीक्षकः, विचारकः, अनुयोक्तृ *m.*, प्राश्निकः.

Example, *s.* उदाहरणं, निदर्शनं, दृष्टांतः; 'for e.' यथा, तथाहि. **2** आदर्शः, प्रमाणं; 'follow an e.' अनुकृ 8 U, प्रमाणं मन् 4 A, वर्त्म अनुगम् 1 P, पदमनुविधा 3 U, (पदमनुविधेयं च महतां). **-Exemplary,** *a.* प्रमाणी-आदर्शी-भूत, दृष्टांतयोग्य, प्रमाणयोग्य. **2** प्रशस्य, श्लाघ्य; अनुकरणीय-करणार्ह. **-ly,** *adv.* प्रमाणवत्, प्रमाणमिव, दृष्टांतरूपेण, अनुकरणीयतया. **-Exemplify,** *v. t.* उदाहृ 1 P, दृष्टांतेन स्पष्टीकृ 8 U or प्रकाश् c. or प्र-दृश् c. **-ication,** *s.* उदाहरणं, निदर्शनं, उदाहरणेन स्पष्टीकरणं.

Exanimate, *a.* निर्जीव, विचेतन. **2** निरुत्साह, भग्नोत्साह.

Exasperate, *v. t.* प्रकुप् c., संक्षुभ् c., रुष् c., क्रुध् c., सं-रभ् c. (रंभयति), क्रोधं उद्दीप् c. **-ed,** *a.* प्रकोपित, संरब्ध, जातामर्ष, इद्धमन्यु, प्रवृद्धक्रोध, संक्षुब्ध, प्रक्षोभित. **-ion,** *s.* प्रकोपणं-नं, संरंभः, क्रोधोद्दीपनं.

Excavate, *v. t.* उत्खन् 1 P, निर्भिद् 7 P or c., विद् 10. **-ion,** *s.* विदारणं, उत्खननं. **2** खातं, गर्तः-र्ता, रंध्रं, बिलं, सुषिरं; 'e. underneath the ground' सुरंगा. **-or,** *s.* खनकः, खातकृत् *m.*

Exceed, *v. t.* अति-इ 2 P, अति-क्रम् 1 U, 4 P; स सत्कारो मनोरथानामप्यभूमिः (S. 7) 'e. ed even my expectations'; अति-चर्-गम् 1 P, लंघ् 1 A, 10; *See* **Beyond** also. **2** अति-शी 2 A, अति-भू 1 P; *See* **Excel. -ing,** *a.* अतिशयिन्. अतिरिक्त, आधिक, अतिरेकिन्. **2** अत्यंत, परम, पर, भूरि, सु pr., अति pr.; 'e. man's power' अतिमानुष; 'e. written orders' आज्ञापत्रमुल्लंघयन्. **-ingly,** *adv.* अत्यंतं, नितांतं, एकांततः, अत्यर्थं, निर्भरं, प्रगाढं, सुतरां, नितरां, प्र-नि-कामं, सातिशयं, अतिमात्रं, अतीव, अति-सु, pr. **-Excess,** *s.* उत्कर्षः, गाढता, बाहुल्यं, प्राचुर्यं, उत्सेकः, अतिशयः, उपचयः, आधिक्यं, अतिरेकः, उद्रेकः. **2** पौनरुक्त्यं, पुनरुक्तता. **3** मर्यादातिक्रमः, अतिक्रमः, अत्याचारः, असंयमः, अपरिमितता. **-ive,** *a.* अत्यंत, अत्यधिक, अत्यर्थ, अतिमात्र, प्रगाढ, परं, परम, सातिशय, निर्भर, उत्कट, नितांत, अपरिमित, एकांत, अतिरिक्त, अतिशुक, तीव्र; gen. by सु-अति-pr. **-ively,** *adv.* अत्यंतं, सु-अति-pr., तीव्रं, बलवत्; *See* above.

Excel, *v. t.* अतिशी 2 A, दूरी-अधः-अधरी-कृ 8 U, विशिष् c.; अतिरिच्-विशिष् pass. (with abl. of person); अतिक्रम् 1 U, 4 P, अति-इ 2 P; oft. by जि 1 P, अभि-परा-भू 1 P, तिरस्कृ, धिक्कृ, प्रत्याख्या 2 P, प्रत्यादिश् 6 P. **-lence,** *s.* विशिष्टता, उत्कर्षः, प्रकर्षः, अतिशयः, श्रेष्ठता, उत्तमता, संपद् *f.*, 'e. of beauty' रूपसंपद्. **2** गुणोत्कर्षः, गुणविशिष्टता-प्रकर्षः. **3** गुणः, गुणवत्ता, परभागः, उत्कृष्टगुणः. **-lency,** *s.* उत्कर्षः, &c. **2** देवः, महाराजः-भागः. **-lent,** *a.* विशिष्ट, उत्कृष्ट, उत्तम, श्रेष्ठ, परम, अग्र, वरेण्य, प्रशस्यतम, प्रवर, गुणवत्, सारवत्, गुणोपेत; oft. by वर-विशेष-in comp., and by words like ऋषभः, पुंगवः, व्याघ्रः, सिंहः, शार्दूलः, इंद्रः, प्रकांडः, उद्धः, तल्लजः, मतल्लिका, मचर्चिका, in comp.; पात्रविशेषः 'e. receptacle'; 'e. cow' गोमतल्लिका, गोतल्लजः, गवोद्धः, गोप्रकांडः, &c.; 'e. man' पुरुषर्षभः, पुरुषसिंहः, &c. **-lently,** *adv.* सुष्ठु, उत्तमं, सु pr.

Except, *v. t.* वृज् 10, परिवृज्, अप-वि-हा 3 P, त्यज् 1 P, अपास् 4 U, मुच् 6 P. **2** व्याहृत् c. (a rule &c.), संकुच् 1 P or c. *-prep.*, **-ing,** वर्जयित्वा, विहाय, मुक्त्वा, अंतरा-अंतरेण (with acc.), विना (with acc., instr., or abl.), ऋते (with abl.); oft. by वर्जं, व्यतिरिक्तं in comp.; गौतमीवर्जमितरा निष्क्रांताः (S. 4). **2** यदि न. **-ion,** *s.* वर्जनं, विवर्जनं, हानं, त्यागः, अपासनं; 'with the e. of'; *See* (*prep.*) above. **2** अपवादः, व्यभिचारः; 'rules have e.-s' उत्सर्गाः सापवादाः; 'as general rules are limited (in scope) by e. s' अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः (K. II. 27); 'that saying has no e. s' अव्यभिचारि तद्वचः (K. V. 36), इति लोकवादः न विसंवादमासादयति (Mallinâtha.); 'counter e.' प्रतिप्रसवः, (युजकांभ्या कर्तरीत्यस्य प्रतिप्रसवः S. K.). **3** वर्जनीयं, वर्ज्यं. **4** दोषः, बाधः-धा, अपवादः; 'take e.' दोषं ग्रह् 9 U, (नात्र दोषं ग्रहीष्यति कुलपतिः S. 3); *See* **Object. -ionable,** *a.* बाध्य, परिहरणीय, वर्ज्य. **-ional,** *a.* असाधारण (णी *f.*), असामान्य, अपवाद-

भूत, अलौकिक (की *f.*); ' e.-ly sharp ' अनन्यसाधारणं पटुः.

Excerpt, *v. t.* उद्-हृ 1 P, निर्हृ, संकल् 10 (कलयति); ' e. passages ' चूर्णीकृ 8 U. -**ion,** *s.* उद्धारः, उद्धृतभागः, निर्हारः, चूर्णि *f.*

Exchange, *v. t.* वि-,नि-मे 1 A, प्रतिदा 1 P, 3 U, (तिलेभ्यः प्रतियच्छति माषान्), प्रतिपण् 1 A, व्यति-हृ 1 P, परिवृत् c. ; ' e. civilities ' सत्कारविनिमयं कृ ; by e. ing clothes ' वेषपरिवर्तनेन-व्यतिहारेण; अन्योन्यसंभिन्नदृशां (Mal. 1) ' who e. ed glances with each other '. -*s.* विनिमयः, परि(री)वर्तः, परिवृत्ति *f.*, परिवर्तनं, नैमेयः, नि(नि)मयः, परिदानं, प्रति-दानं-पणनं, व्यतिहारः ; oft. by अन्योन्य or प्रति in comp. ; 'e. of favours' अन्योन्योपकारः; ' e. of looks ' अन्योन्यदृष्टिपातः, परस्परालोकनं ; ' e. of blows ' प्रतिघातः ; ' in e. for ' विनिमयेन, व्यतिहारेण, प्रतिदानेन. 2 भांड-द्रव्य-विनिमयः. 3 श्रेष्ठिचत्वरं.

Exchequer, *s.* राजधनागारं, राजस्वकोषः ; ' chancellor of the e. ' कोषाधीशः, कोषाध्यक्षः.

Excise, *v. t.* राजदेयकरं-शुल्कं-निरूप् 10 or निर्दिश् 10 or स्था c. (स्थापयति), -*s.* राजस्वं, करः, शुल्कं. -**man,** *s.* करनिरूपकः, शुल्काधिकारिन् *m.*, कराध्यक्षः, शुल्कग्राहः.

Excision, *s.* उच्छेदः, कर्तनं, उत्पाटनं, उद्धरणं, विनाशः.

Excite, *v. t.* उत्तिज् c., प्रकुप् c., सं-वि-क्षुभ् c., उत्-सं-तप् c., उद्-दीप् c.,उद्युज् 10, उत्था c. (उत्थापयति), मोत्सह् c., प्रचुद् 10, वृध् c., प्रवृत् c., संधुक्ष् 10 (feelings &c.). 2 जन् c. (जनयति), उत्पद् c., प्रवृध् c.; 'my curiosity is the more e. ed' कुतूहलाधिकतरमुपजनितं मे कौतुकं (Ks. 134) ; ' with anger e. ed ' संजातामर्ष, उद्दीपितकोप ; oft. by dat. with or without भू ; 'his speech e.-ed laughter ' तद्वचो हासाय बभूव; *See* **Lead to.** -**able,** *a.* कोपन, उत्तेजनीय, सुलभकोप, क्रोधिल, शीघ्रकोपिन्. -**ation, -ment,** *s.* उत्तेजनं, उत्तापः, उत्थापनं, प्रकोपः, उद्दीपनं, संतापः-पनं, सं-,वि-,क्षोभः, संरंभः, चित्तोद्वेगः, चित्तोत्तापः मनस्तापः, कोपोद्दीपनं. -**ed,** *a.* संरब्ध, प्रकोपित, क्षुब्ध, उत्तेजित, जातरोष, इद्धमन्यु, संतप्त; सं-वि-क्षोभित; ' in an e. mood ' क्रोधावेशेन; रोषवशं गत. 2 उत्पन्न, जात, जनित. -**er,** *s.* उद्दीपकः, उत्तेजकः, संक्षोभकः.

Exclaim, *v. i.* आ-उत्-क्रुश् 1 P, उच्चैः घुष् 10, तारस्वरेण वद् 1 P, आ-रट् 1 P, उच्चैः उद्दीर् c. -**Exclamation,** *s.* उत्क्रोशः, आरटनं, घोषणं-णा, उच्चैः स्वरः, उद्गारः ; ' e. of joy ' हर्षनिस्वनः, हर्षोद्गारः.

Exclude, *v. t.* नि-प्रति-षिध् 1 P, नि-अप-वृध् 7 U, नि-वृ c., व्या-वृत् c., (तुषात्तः पूर्वपक्षं व्यावर्तयति S. B.), बाध् 1 A, निरस् 4 U. 2 बहिष्कृ 8 U, निःसृ c., निष्कास् c., निराकृ, अपाहृ 6 P, व्यतिरिच् 7 P or c. 3 वृज् 10, त्यज् 1 P, वि-अप-हा 3 P, मुच् 6 P, अपास् 4 U. -**Exclusion,** *s.* निषेधः, व्यावर्तनं, व्यावृत्ति *f.*, व्यतिरेकः, बाधः-धा. 2 निराकरणं, निःसारणं. 3 वर्जनं, व्युदासः, हानं; 'to the e. of ' विहाय, मुक्त्वा, अतिक्रम्य, उज्झित्वा. -**Exclusive,** *a.* व्यावर्तक, निषेधक, निवारक, बाधक. 2 अनन्यसाधारण (णी *f.*); अनन्यसामान्य, अनन्यमुक्त; ' e. of ' विहाय, वर्जयित्वा, मुक्त्वा, हित्वा, रहित-हीन-in comp.; *See* **Except.** -**ly,** *adv.* अनन्यसाधारणं, केवलं, अन्यव्यतिरेकेण; ' I am e. thy servant ' अहं तवानन्यसाधारणो दासः (M. 4). -**ness,** *s.* अनन्यसामान्या वृत्ति *f.*

Excogitate, *v. t.* चिंत् 10, परिक्लृप् c.; *See* **Consider.** -**ion,** *s.* चिंतनं, परिकल्पनं.

Excommunicate, *v. t.* (समाजात्) बहिष्कृ 8 U, निराकृ, अपास् 4 U, भ्रंश् c., च्यु c., अपांक्तीकृ; ' one e. ed ' अपांक्तेयः, बहिष्कृतः. -**ion,** *s.* बहिष्कारः, अपांक्तेयत्वं.

Excoriate, *v. t.* त्वचं-चर्म-उल्लिख् 6 P or निर्घृष् 1 P or कृत् 6 P or छिद् 7 P, निस्त्वचीकृ 8 U. -**ion,** *s.* त्वक्छेदः-भेदः, चर्मक्षति *f.*-विदारणं-उल्लिखनं-पीडनं.

Excortication, *s.* निस्त्वचीकरणं.

Excrescence, *s.* गंडः, विस्फोटः, शोफः ; fleshy e. ' अधिमांसं, मांसपिंडः.

Excrete, *v. t.* उत्सृज् 6 P, उच्चर् c., निःसृ c.; मलोत्सर्गं कृ 8 U. -**ion,** -**Excrement,** *s.* विष्ठा, उच्चारः, शकृत् *n.*, पुरीषं, गूथं; *See* **Dung;** ' e. and urine ' विण्मूत्रं, मूत्रपुरीषं. -**al,** *a.* उच्चारित, अवस्कृत, उत्सृष्ट.

Excruciate, *v. t.* अत्यंतं व्यथ् c. (व्यथयति) or बाध् 1 A or संतप् 1 P or c., प्र-मंथ् 9 P. -**ing,** *a.* मर्मच्छिद्-स्पृश्, अरुंतुद, प्रमाथिन्, अतिव्यथाकर (री *f.*), अतितीव्र, नितांतकठिन. -**ion,** *s.* तीव्र-तिग्म-वेदना, अतियातना.

Exculpate, *v. t.* (दोषात्-अपराधात्) वि-परि-शुध् c.; वि-,मुच् 6 P or c., निर्दोषीकृ 8 U, दोषं परि-प्र-मृज् 2 P or क्षल् 10; ' he e. ed himself ' आत्मानं दोषमुक्तं चकार. -**ed,** *a.* निर्दोष, निरपराध, दोषमुक्त, विशुद्ध. -**ion,** *s.* दोषशोधनं-मुक्ति *f.*, अपराधक्षालनं-मार्जनं, &c. -**ory,** *a.* दोषप्रमार्जक-मोचक, दोषक्षालन (नी *f.*).

Excursion, *s.* पर्यटनं, भ्रमणं, विहारः, विहरणं. 2 पथत्यागः-भ्रंशः, मार्गातिक्रमः, विचलनं, उत्क्रमः. 3 अभिद्रवः, आक्रमः, आपातः.

Excursive, *a*. भ्रमणशील, त्यक्तमार्ग. 2 सर्वतो धाविन्.

Excuse, *v. t.* क्षम् 1 A, मृष् 1 P, 10, सह् 1 A, तिज् desid. (तितिक्षते). 2 दोषात् मुच् c. or मुच्; 'e. a person' दोषं-अपराधं-क्षम् (with gen.); 'e. a fine' दंडं अवसृज् 6 P or मुच् 6 P; 'e. oneself' अप-व्यप-दिश् 6 P, उत्तरं दा 3 U, अपदेशं-छद्म-कृ 8 U, आत्मानं विमुच् c.; 'e. ing myself on the ground of head-ache' शिरःशूलस्पर्शनमपदिशन् (D. K. II. 2); 'e. me' प्रसीदतु भवान्. —*s*. अप-व्यप-देशः, उत्तरं, निमित्तं, छलं, छद्मन् *n*., विमोचनहेतुः. 2 दोषक्षालनं, पापशोधनं, क्षमाप्रार्थना; oft. by हेतुः; 'under the e. of illness' अस्वास्थ्यहेतोः, अनामयापदेशेन. **-less**, *a*. निरुत्तर. 2 अक्षंतव्य.

Execrate, *v. t.* शप् 1 U, आक्रुश् 1 P, गर्ह् 1, 10 A, अभिशंस् 1 P. **-ion**, *s*. शापः, आक्रोशः, अभिशंसनं. **-Execrable**, *a*. गर्ह्य, गर्हणीय, अधम, नीच; *See* **Accursed.**

Execute, *v. t.* अनुष्ठा 1 P, सं-निः-पद् c., कृ 8 U, वि-धा 3 U, आ-चर् 1 P, निर्वह् c., साध् 5 P or c., निर्वृत् c.; 'e. thy business' स्वनियोगमशून्यं कुरु. 2 हन् 2 P, व्या-पद् c., प्राणदंडं-देहदंडं-आदिश् 6 P, दंड् 10; 'he was ordered to be e. e-d' तस्य वध-देह-दंड आदिष्टः, वध्यतामसौ इति आदिष्टं. **-ion**, *s*. अनुष्ठानं, आचरणं, विधानं, करणं, संपादनं, निष्पत्ति-सिद्धि *f*., निर्वाहः-हणं. 2 घातः, हननं, हत्या, व्यापादनं, वधः; 'place of e.' वध्यस्थानं-भूमि *f*.; 'sentence of e.' प्राणदंडः, उत्तमसाहसं. **-ioner**, *s*. घातकः, मातंगः, दंडपाशिकः, वध्यपुरुषः, वधाधिकृतः. **-ive**, *a*. निर्वाहक, निष्पादक विधायक, कार्यक्षम, अनुष्ठाननियुक्त, कार्यनिर्वाहक. **-or**, *s*. मृतलेखाधिकारिन् *m*., (मृतस्य) उत्तरसाधकः.

Exegesis, *s*. विवरणं, व्याख्यानं; व्याकरणं. **-Exegetical**, *a*. विवरणकृत्, प्रकाशक.

Exempt, *v. t.* मुच् 6 P or c., मोक्ष् 10, वि-अव-सृज् 6 P, वृज् 1 P, 10; 'e. from fine' दंडादानं क्षम् 1 A; 'e. from taxes' करादानं अनुज्ञा 9 U. **-a.**, **-ed**, *a*. मुक्त, वर्जित, हीन, रहित; oft. by अ, निर्, वि, वीत, गत, in comp.; 'e. from pride' गतावलेप, वीतदर्प, अगर्व, &c.; 'e. from avarice' निर्लोभ, वितृष्ण, लोभरहित. &c. 2 अनायत्त, अवश. **-ion**, *s*. मुक्ति *f*., मोक्षः, वर्जनं, रहितत्वं, मोचनं, अभावः; oft. by अ or अन् in comp.; अनवलेपः 'e. from pride, दंडाभावः 'e. from fine,' &c.

Exequies, *See* **Obsequies.**

Exercise, *s*. प्रयोगः, व्यापारः, अनुष्ठानं, आचरणं. 2 अभ्यासः, निषेवणं, अभ्यस्तता, आवृत्ति *f*., चर्या. 3 व्यवसायः, श्रमः, चेष्टा, उद्योगः, व्यापारः; 'bodily e.' व्यायामः, परिश्रमः; 'materials for taking e.' व्यायामोपकरणानि; 'military e.' रणशिक्षा, शस्त्राभ्यासः, इष्वभ्यासः; 'shooting e.' शराभ्यासः, उपासनं; 'usual e.' नित्यकृत्यं. —*v. t.* उप-प्र-युज् 7 A, 10, व्या-पृ c. 2 अभ्यस् 4 U; (सदा) आचर् 1 P, अनुष्ठा 1 P, आ-नि-सेव् 1 A, अनु-परि-शील् 10, आ-यस् c., व्या-यम् c.; 'e. soldiers' शिक्ष् c., रणशिक्षां दा 3 U; 'e. oneself' व्यायम् 1 P, उद्यम्, व्यव-सो 4 P, चेष्ट् 1 A; व्यायामं-शरीरश्रमं-कृ 8 U. —*v. i.* परिश्रमं-व्यायामं-कृ; 'e ed with an iron club' अयोदंडेन श्रममकरोत् (Ka.76).

Exert, *v. t.* नि-प्र-उप-युज् 7 A, 10, व्या-पृ c., प्रवृत् c.; 'e. oneself' प्रयत् 1 A, चेष्ट् 1 A, उद्यम् 1 P, व्यव-सो 4 P, प्रवृत् 1 A; 'e. one's utmost' यावच्छक्यं प्रयत्. **-ion**, *s*. व्यवसायः, उत्साहः, चेष्टा, व्यापारः, चेष्टितं, कर्मयोगः, यत्नः, उद्यमः, उद्योगः; *See* **Attempt.** 2 आयासः, श्रमः, परिश्रमः, कायक्लेशः-आयासः.

Exfoliate, *v. i.* परिपुट् 6 P, विगल् 1 P

Exhale, *v. t.* उद्-गॄ 6 P, उच्छ्वस् 2 P, निश्वस्, उत्क्षिप् 6 P, उद्वम् 1 P, निर्मुच् 6. P उदीर् c., निर्गम् c. (गमयति), प्र-वा 2 P, निष्कॄ 6 P, उद्गम् c. 2 (As water) आ-पा 1 P, उच्छुष् c., आचम् 1 P, बाष्पीकृ 8 U; 'trees e. ing fragrance' परिमलोद्गारिणः वृक्षाः. **-ation**, *s*. उद्गारः, निश्वासः, उच्छ्वासः, उच्छ्वसितं, निर्गमः, उद्वमनं, उत्क्षेपः. 2 बाष्पः, धूमिका, धूमः. 3 बाष्पोद्गमनं, धूमोद्गारः.

Exhaust, *v. t.* उत्-सं-शुष् c., आ-पा 1 P. 2 शून्याकृ 8 U, निःशेषीकृ, सर्वसारं हृ 1 P, विरिच् 7 P or c. 3 क्षि 1 P, क्षै c. (क्षपयति), नश् c., व्ययं-क्षयं-कृ, अप-चि 5 U; 'his wealth was e. ed in performing meritorious deeds' धर्मकर्माणि कुर्वतस्तस्य धनक्षयः संजातः (P. v. 1.); who had e. ed his whole treasure in gifts (charity)' निःशेषविश्राणितकोषजातं (R. v. 1.). 4 खिद् c., क्लम् c. (क्लमयति), श्रम् c., अव-सद् c., ग्लै c., (ग्ला-ग्लपयति; 'I feel e. ed' क्लांतोस्मि, अवसन्नानि मे गात्राणि. **-ed**, *a*. शोषित, विरिक्त, निःशेषीकृत. 2 क्षीण, अपचित. 3 श्रांत, क्लांत, खिन्न, अवसन्न, ग्लान. **-ion**, *s*. शोषणं. 2 क्षयः, परिक्षयः, नाशः, व्ययः अपचयः. 3 खेदः, श्रमः, क्लमः, ग्लानि *f*., अवसादः, श्रांति-क्लांति *f*. **-less**, *a*. अक्षय, अनाश्य, अविनाशिन्.

Exhibit, *v. t.* प्र-दृश् c., प्रकाश् c., निर्दिश् 6 P, प्रकटीकृ 8 U, प्रकटयति (D.), व्यंज् 7 P or c., व्यक्तीकृ, आविष्कृ, प्र-सृ c. **2** (On the stage) प्रस्तु 7 A, 10, अभिनी 1 P; *See* **Act.** **-er,** *s.* प्रदर्शकः, प्रकाशकः. **-ion,** *s.* प्रदर्शनं, व्यंजनं, आविष्करणं, &c. **2** वृत्तिसाधनं, वृत्ति *f.* **3** अभिनयः, आविर्भावः. **-ioner,** *s.* वृत्तिभुज् *m.*

Exhilarate, -ion, *See* **Delight.**

Exhort, *v. t.* सोत्सुकं याच् 1 A or प्रार्थ् 10 A, उप-दिश् 6 P, अनु-शास् 2 P, प्र-सं-चुद् c. **2** आ-समा-श्वस् c., प्रोत्सह् c., प्र-चुद् 10, प्रवृत् c., उत्तुज् 10. **-ation,** *s.* उपदेशः, उपदेशवचनं, सोत्सुकप्रार्थना, प्रबोधनवाक्यं. **2** प्रोत्साहनं, प्रेरणं, प्रचोदनं, उत्तेजनं, प्रबोधनं, समाश्वासनं, प्रवर्तनं. **-ative, -atory,** *a.* प्रबोधक, उपदेशक. **-er,** *s.* उपदेशकः, प्रबोधकः.

Exhume, *v. t.* (शवं) उत्खन् 1 P. **-ation,** *s.* उत्खननं.

Exigence, -cy, *s.* आवश्यकत्वं, अपरिहार्यत्वं, अवश्यप्रयोजनं-कार्यं. **2** अवसरः, प्रस्तावः, समयः, कालः. **3** आपद्-विपद् *f.*, संकट-कष्ट-समयः-कालः, विपत्समयः, कृच्छ्रं-कष्टः-ष्टं, दुर्गति *f.* **-Exigent (esnt),** *a.* अपरिहार्य, आवश्यक.

Exiguous, *a.* तनु, अल्प.

Exile, *v. t.* प्र-निर्-वि-वस् c., प्र-व्रज् c., (स्वदेशात्) निः-सृ c., अपाकृ 8 U, बहिष्कृ. **-s.** वि-प्र-वासः-सनं, प्रव्राजनं. **2** प्रव्रजनं, दूरसंस्थिति *f.*, विवासनविधिः; 'to go into e.' प्रव्रज् 1 P.

Exist, *v. i.* भू 1 P, वृत् 1 A, विद् 4 A, अस् 2 P; जन् 4 A, उत्पद् 4 A. **2** जीव् 1 P, प्राण् 2 P. **3** स्था 1 P, प्रवृत्, आस् 2 A. **-ence,** *s.* अस्तित्वं, सत्ता, सत्त्वं, अवस्था, भावः, सद्भावः, संभवः, वर्तनं. **2** जीवितं, जीवनं, वृत्ति *f.*, प्राण-असु-धारणं; 'worldly e.' संसारः, भवः. **-ent,** *a.* सत्, विद्यमान, वर्तमान, जीविन्; 'self-e' आत्मभूः, स्वयंभूः.

Exit, *s.* निष्क्रमः,-मणं, निर्याणं; अपक्रमः, अपगमः, निर्गमः. **2** (In dramas) निष्क्रांत *a.*; 'exeunt omnes' निष्क्रांताः सर्वे.

Exodus, *s.* निर्गमः बहिर्गमनं.

Ex-officio, *adv.* अधिकारवशात्.

Exonerate, *v. t.* **Exculpate,** q. v. **2** भारं अपनी 1 P or अवतॄ c.

Exorable, *a.* अनुनेय, प्रसादनीय, सांत्वनीय; 'not e.' निरनुक्रोश.

Exorbitant, *a.* अमर्याद, अमित, अपरिमित, अतिरिक्त, सातिशय, अतिमात्र, अत्यधिक; *See* **Excessive.** **-Exhorbitance, -cy,** *s.* अतिरेकः, मर्यादातिक्रमः, उद्रेकः, आधिक्यं.

Exorcise, *v. t.* (भूतं) दूरीकृ 8 U, निःसृ c., भूतावेशाद् मुच् c. **-Exorcism,** *s.* भूतापसारणं.

Exordium, *s.* प्रस्तावः, वाङ्मुखं, आमुखं, मुखबंधः, उपोद्घातः.

Exoteric, *a.* साधारण (णी *f.*).

Exotic, *a.* विदेशीय, विदेशज, अन्यदेशोद्भव, वैदेशिक (की *f.*).

Expand, *v. t.* विस्तॄ c., प्र-वृध् c., वि-तन् 8 U, प्र-वि-सृ c., 'e. itself' व्याप् 5 P. व्यश् 5 A. **2** वि-वृ 5 U, प्र-वि-काश् c.. प्रपंचयति (D.). **3** (As flowers &c.) विकाश् c., विकस् c., भिद् 7 P or c., स्फुट् c., वि-स्फुर् c. (स्फारयति). **-v. i.** वि-प्र-सृ 1 P, प्र-,वृध् 1 A, pass. of roots above. **2** विकस् 1 P, स्फुट् 6 P, फुल्ल् 1 P, भिद् pass.; *See* **Blossom;** विस्फुर् 6 P; 'whose boyhood gradually e. ed into youth (manhood)' क्रमाद्यौवनभिन्नशैशवः (R. III 32); 'with his eyes e. ed through joy' हर्षोत्फुल्लनयनः. **3** विजृंभ् 1 A **-Expanse,** *s.* प्र-वि-तानः, प्रसरः, विस्तारः. आभोगः, (आभोगस्तपोवनस्य S. 1); 'in the e. of ocean' विस्तीर्णे सागरे, 'in this e. of universe' महति जगज्जाले. **-ion,** *s.* विस्तारः, प्रसारः, विततिः *f.*, प्रसरः, विस्तरः, प्रसरणं, व्याप्ति *f.* **2** प्रपंचः, विवरणं. **-ive,** *a.* व्यापक, वि-प्र-सारिन्, विस्तारिन्, विसृत्वर, विसृमर.

Ex parte, *a.* एकपक्षीय.

Expatiate, *v. i.* **Enlarge** (upon), q. v. **2** परिभ्रम् 1, 4 P.

Expatriate, *See.* **Exile.**

Expect, *v. t.* अपेक्ष् 1 A, उद्-दृश् 1 P; आशंस् 1 A, उदीक्ष्; प्रति-पा c. (पालयति), प्रति-इष् 6 P, प्रतीक्ष् (wait for); 'I am e. ing my brother' मम भ्रातुरागमनं प्रतीक्षे; वर्त्म अवलोकयामि (Ka. 220); पत्नी त्वां प्रतीच्छति (V. 2). **-ant,** *a.* अपेक्षिन्, अपेक्षक, प्रत्याशिन्, आकांक्षिन्, समप्रत्याश. **-ation,** *s.* अपेक्षा, आशा, प्रत्याशा, उदीक्षणं, आशंसा, प्रतीच्छा, प्रतीक्षा-क्षणं. **-ed,** *a.* अपेक्षित, आकांक्षित, समर्थित, तर्कित; 'un-e. call' अतर्कितागमनं

Expectorate, *v. t.* (श्लेष्माणं) उद्-गॄ 6 P or निःसृ c., निष्ठिव् 1, 4 P. **-ion,** *s.* निष्ठ्युति *f.*, निष्ठीवनं, श्लेष्मोद्गारः.

Expedient, *a.* युक्त, उचित, योग्य, उपपन्न, उपयुक्त, हित, हितावह. **-s.** उपायः, कल्पः, साधनं, गति *f.*, उपक्रमः, उपकरणं, योगः, गुणः; षड् गुणाः 'six e. s.' **-ly,** *adv.*

युक्तं, उपपन्नं, यथोचितं.–**Expediency,-ce,** *s.* औचित्यं, युक्तता, उपपत्तिः *f.*, उपयोगः, हितावहत्वं.

Expedite, *v. t.* त्वर् c. (त्वरयति), शीघ्रं संपद् c. or प्रवृत् c. or साध् c. or वि-धा 3 U. 2 शीघ्रं प्रेष् c. or प्रेर् c. **-ion,** *s.* त्वरा, शीघ्रता, क्षिप्रता, जवः, वेगः, अविलंबः, शीघ्रनिर्वाहणं, क्षिप्रकारित्वं. 2 यात्रा, प्रयाणं, प्रस्थानं, यानं, अभिषेणनं, अवपातः; 'to send an e.' सैन्यं प्रस्था c. (स्थापयति). 3 Enterprize, q. v. **-ious,** *a.* त्वरित, शीघ्र-क्षिप्र-कारिन्, सत्वर, अदीर्घसूत्र, अविलंबित, द्रुत, लघु. **-iously,** *adv.* शीघ्रं, सत्वरं, द्रुतं, &c.

Expel, *v. t.* Exile, q. v. 2 निष्कस् c., बहिष्कृ 8 U, अपा-निरा-कृ, निःसृ c., अपध्वंस् c., निर्धू 5, 9 U; *See* **Drive, Dispel.** 3 (From society) अपपात्रयति (D.), अपांक्तीकृ 8 U. **-led,** *a.* निष्कासित, अवकृष्ट, अपध्वस्त, निर्धूत, धिक्कृत. **-Expulsion,** *s.* अपसारणं, निष्कासनं, निराकरणं, विवासनं, प्रव्राजनं.

Expend, *v. t.* व्यय् 10 (व्यययति), उत्-वि-सृज् 6 P, त्यज् 1 P, विनि-युज् 7 A, 10, प्र-उप-युज् 2 क्षि 1 P, क्षै c. (क्षपयति), अप-चि 5 U, क्षयं-व्ययं-कृ 8 U. **-Expense, Expenditure,** *s.* व्ययः, विसर्गः, उत्सर्गः, त्यागः, विनियोगः; धनत्यागः, व्ययः, अर्थोत्सर्गः. 2 क्षयः, अपचयः, अपहारः. **-ive,** *a.* बहुमूल्य, महार्ह-र्घ, बहुव्यय, बहुव्ययसाध्य, महामूल्य. **-ively,** *adv.* बहुव्ययेन, बहुमूल्येन.

Experience, *v. t.* अनुभू 1 P, उप-भुज् 7 U, अश् 5 A, आप् 5 P, आसद् c., ज्ञा 9 U, विद् 2 P, परीक्ष् 1 A. 2 **Suffer,** q. v. **-s.** अनुभवः, परीक्षणं, वेदनं, प्रतीति *f.*, ज्ञानं, बोधः, भोगः, भुक्ति *f.* 2 बहुदर्शित्वं, अनुभवजन्यं ज्ञानं, बुद्धिपरिपाकः. 3 अभ्यासः, आचरणं. **-ed,** *a.* बहुदर्शिन्, अनुभविन्, बहुश्रुतवत्, परिणतप्रज्ञ, पक्वबुद्धि, बहुदृष्ट, साक्षात्; 'I am an e. teacher (of the art)' कृतप्रयोगोस्मि (M. 1).

Experiment, *s.* प्रयोगः, परीक्षा-क्षणं, अनुभवः. **-v.** *t.* परीक्ष् 1 A, अनुभू 1 P; प्रयुज् 7 A, 10. **-al,** *a.* अनुभवलब्ध-प्राप्त, अनुभूतिमूल. 2 परीक्षक, परीक्षार्थं कृत. **-ally,** *adv.* परीक्षणार्थं, अनुभूत्यर्थं. 2 परीक्षापूर्वं, अनुभवेन-भवात्. **-er, -alist,** *s.* परीक्षकः.

Expert, *a.* दक्ष, प्रवीण, पटु, विज्ञ, निपुण, चतुर; विद्-ज्ञ in comp.; विचक्षण, विशारद; *See* **Skilful. -ly,** *adv.* सपाटवं, सकौशलं. **-ness,** *s.* पाटवं, कौशलं, नैपुण्यं, दक्षता, चातुर्यं, विज्ञता, विदग्धता, &c.

Expiate, *v. t.* वि-सं-परि-शुध् c., निष्कृ 8 U, निराकृ, शम् c. (शमयति), अपानुद् 6 P, प्रमृज् 2 P or c., प्रायश्चित्तेन पू 9 U or शुध् c. or क्षुप् c., पापनिष्कृतिं कृ. **-ion,** *s.* शोधनं, पावनं; प्रायश्चित्तं, पापनिष्कृति *f.*-प्रक्षालनं-विशुद्धि *f.*-क्षालनं-मार्जनं, शुद्धि *f.* **-ory,** *a.* पावन, पापनाशक-शम, अघमर्षण (णी *f.*), विशोधक, पापघ्न (घ्नी *f.*).

Expire, *v. i.* निश्वस् 2 P, श्वासं उत्क्षिप् 6 P, or निर्गम् c. (गमयति). 2 उद्-मृ 6 P; *See* **Exhale. -v.** *i.* प्राणान् हा 3 P or त्यज् 1 P, मृ 6 A, उत्क्रांतवायु *a.* भू, उपरम् 1 P, संस्था 1 A; *See* **Die.** 2 समाप् pass., अवसो pass., निवृत् 1 A, विरम्, अवसद् 1 P, क्षि pass. **-ation, -y,** *s.* प्राणत्यागः; निश्वासः-सनं, उपरमः. 2 निवृत्ति *f.*, समाप्ति *f.*, विरामः, अत्ययः, क्षयः, अंतः, अवसानं, शेषः, विच्छेदः. **-ing,** *a.* कंठगतप्राण, आसन्नमृत्यु, मुमूर्षु.

Explain, *v. t.* व्या-ख्या 2 P, व्याचक्ष् 2 A, निरूप् 10, विवृ 5 U, द्युत् c., व्यंज् 7 P or c, स्फुटी-विशदी-कृ 8 U, व्या-कृ, प्र-वच् 2 P, प्रकाश् c., स्पष्टीकृ, प्रबुध् c. 2 वर्ण् 10, कथ् 10, प्रवद् 1 P, प्रकृत् 10. **-er,** *s.* व्याख्यातृ *m.*, प्रकाशकः, प्रवक्तृ *m.*, वादिन् *m.* **-Explanation,** *s.* व्याख्यानं, विवरणं, व्याकरणं, प्रकाशनं, स्पष्टीकरणं, विवृत्ति *f.*, निरूपणं. 2 समाधानं, शोधनं. **-Explanatory,** *a.* अर्थव्यंजक-द्योतक-प्रकाशक, वाचक, विवरणकृत्.

Expletive, *s.* पादपूरणं, वाक्यालंकारः.

Explicate, *See* **Explain.**

Explicit, *a.* स्पष्ट, व्यक्त, परिस्फुट, भिन्नार्थ, सुप्रकाश. **-ly,** *adv.* व्यक्तं, स्फुटं, स्पष्टं.

Explode, *v. i.* महाशब्देन विद्-विभिद् pass., महाशब्दपूर्वं स्फुट् 6 P or विदल् 1 P. **-v.** *t.* कर्कशनिस्वनेन निंद् 1 P or असंतोषं दृश् c. or सूच् 10. 2 निरस् 4 U, खंड् 10, विलुप् c., अपा-कृ 8 U. **-Explosion,** *s.* सशब्दभंगः-स्फोटनं, महाशब्दपूर्वं विदारणं. **-Explosive,** *a.* शीघ्रदाह्य, विदारणशील.

Exploit, *s.* पराक्रमः, अवदातं कर्मन् *n.* आश्चर्य-अद्भुत-कर्मन् *n.*, विक्रमः, विचेष्टितं.

Explore, *v. t.* अन्विष् 4 P, निरूप् 10, मृग् 10 A, निरीक्ष् 1 A, अनुसं-धा 3 U, मार्ग् 10. **-ation,** *s.* अन्वेषणं, निरूपणं, मार्गणं, जिज्ञासा. **-er,** *s.* अन्वेष्टृ *m.*

Exponent, *s.* (In mathematics) घातचिह्नं **-a.** प्रकाशक, द्योतक.

Export, *v. t.* विदेशं नी 1 P or प्र-हि 5 P, बहिर्देशं प्रेष् c. or वह् 1 P or c. **-s.** निर्गतं द्रव्यं-भांडं. **-ation,** *s.* विदेशनयनं, निर्गमनं.

Expose, *v. t.* (lit.) उच्छद् 10, अपा-वृ 5 U, विवस्त्रीकृ 8 U, प्रकाश् c., प्रदृश् c. 2 व्यक्तीकृ, प्रत्यक्षीकृ, आविष्कृ, सर्वसमक्षं आ-

विवृ; *See* **Explain** also. **3** (Make liable) पर्यु-नी 1 P or कृ 8 U, स्थानं-आस्पदं कृ; 'e. ed yourself to trouble' भवतात्मा क्लेशस्य पदमुपनीतः (S. 1); 'e.-ed to the charge of cowardice' कातर इति वाच्यतां गतः-द्रोषपात्रं जातः; 'e. ed to hundreds of calamities' व्यसनशतशरव्यतामुपगताः (Ks. 107); 'e. to contempt' तिरस्कारस्थानं कृ; 'e. to the sun' आतपे धा 3 U or शुष् c., आतपाय उज्झ् 6 P; 'e. for sale' क्रयार्थं प्र-सृ c. **-ed,** *a.* अनाच्छादित, अनावृत, &c.;'e. d for sale' क्रय्य. **-ition,** *s.* विवरणं, व्याख्यानं, प्रकाशनं, स्पष्टीकरणं. **-itor,** *s.* विवृतिकारः, वृत्तिकारः, व्याख्यातृ *m.*, अर्थप्रकाशकः. **-ure,** *s.* विवृति *f.*, प्रदर्शनं, प्रकाशनं, व्यक्तीकरणं, स्वरूपाविष्करणं 'e. to heat' आतपलंघनं; (S. 3).

Expostulate, *v. i.* प्रत्यादिश् 6 P, (अपवात्) व्यावृत् c., निवारयितुं-निर्यतुं उद्यम् 1 P or प्रयत् 1 A; *See* **Dissuade. -ion,** *s.* प्रत्यादेशः, निवर्तनवाक्यं, निषेधः, निवारणं, प्रबोधवचनं.

Expound,-er, *See* **Explain,-er.**

Express, *a.* व्यक्त, स्फुट, परिस्फुट, सुप्रकाश, भिन्नार्थ, असंदिग्ध; 'in e. terms' भिन्नार्थं, स्पष्टं. **2** विशिष्ट. **-s.** (Messenger) जंघाकारिकः, जांघिकः. **2** जंघालः, अतिजवः, प्रजविन्-वेगिन् *m.*, जवनः, त्वरितः, तरस्विन् *m.* **-v. t.** व्यंज् 7 P or c., आविष्कृ 8 U, प्रदृश् c., सूच् 10, द्युत् c., प्रकटीकृ, निर्दिश् 6 P, लक्ष् 10, प्रकटयति (D.). **2** वच् 2 P, उच्चर् c., उदीर् c. कथ् 10, शंस् 1 P, वद् 1 P, उदाहृ 1 P, व्याहृ, आ-नि-विद् c., ख्या 2 P, प्रकाश् c., बुध् c., ज्ञा c. (ज्ञापयति), अभि-धा 3 U; 'e. oneself' मनोगतं शंस्, वाचं उदीर्; 'e. by gesticulation' नट् 10, निरूप् 10, सूच्, अभिनी 1 P. **3** निष्पीड् 10, निष्कुष् 1 P, निर्दुह् 2 U, निर्हृ 1 P. **-ion,** *s.* व्यंजनं, प्रकाशनं, बोधनं, आ-निवेदनं, ज्ञापनं, आविष्करणं, कथनं, उदाहारः-हरणं, ख्यापनं. **2** निष्पीडनं, निष्कर्षणं. **3** वदनं, आस्यं; 'he had a smiling e.' हास्यवदन आसीत्; 'wore an angry e.' कुपित इव बभौ. **4** वचनं, उक्ति *f.*; वाक्यं, पदं, शब्दः, वचस् *n.*, वाच् *f.*; 'authoritative e.' आप्तवचनं, प्रमाणं. **5** रीति *f.*, मार्गः, पद्धति-सरणि *f.* **-ly,** *adv.* स्पष्टं, व्यक्तं, परिस्फुटं, भिन्नार्थं. **-ive,** *a.* व्यंजक, वाचक, सूचक, द्योतक, अभिधायक, गमक, दर्शक. **2** सार्थ, साकूत, पूर्णार्थ, अर्थवत्. **-ively,** *adv.* सार्थं, साकूतं. **2** स्पष्टं, सुव्यक्तं, भिन्नार्थं, परिस्फुटं, व्यंजकतया. **-iveness,** *s.* व्यंजकत्वं, अर्थवत्ता, साकूतता.

Expropriate, *v. t. See* **Dispossess.**

Expugn, *v. t.* (युधि) लंघ् 1 A, 10, वशीकृ 8 U, आक्रम् 1 U, 4 P, वि-जि 1 A.

Expunge, *v. t.* वि-,लुप् c., व्या-अप-मृज् 2 P or c., व्यामृश् 6 P or c., उच्छिद् 7 P, विनश् c. **-Expunction,** *s.* वि-,लोपः, व्यामर्दः, उच्छेदः, नाशः.

Expurgate, *v. t.* पू 9 U, शुध् c., पवित्रीकृ 8 U. **-ion,** *s.* पावनं, शोधनं. **-ory,** *a.* पावक-न.

Exquisite, *a.* अत्युत्तम; विशिष्ट, उत्कृष्ट, परम; *See* **Choice;** 'e beauty' अतिमनोहरं-अतिरम्यं-लावण्यं; 'e. delight' परमानंदः. **2** सूक्ष्म. **3** तीक्ष्ण, तीव्र, उग्र (of pain). **-ly,** *adv.* परमं, उत्तमं, अति-परम- in comp. **-ness,** *s.* विशिष्टता, उत्तमता, &c.

Exsiccate, *v. t.* शुष् c., उच्छुष् c.; *See* **Dry. -ion,** *s.* उच्छोषणं, शोषः. **-ive,** *a.* शोषक.

Extant, *a.* विद्यमान, उपलब्ध, वर्तमान.

Extemporary, -raneous, *a.* तत्क्षणकृत, अचिंतितपूर्व, अयत्नकृत, अकल्पितपूर्व. **2** प्रस्तावोपयुक्त, समयोचित. **-ly, Extempore,** *adv.* पूर्वचिंतां विना, अयत्नपूर्वं, पूर्वकल्पनां विना.

Extend, *v. t.* तन् 8 U, वि-प्र-°; विस्तृ-स्तृ 5, 9 U or c., प्र-सृ c., आ-यम् 1 P, वृध् c., दीर्घीकृ 8 U, प्रथ् 10. **2** प्रदा 3 U, वितृ 1 P. **-v. i.** वितन्-विस्तृ pass., व्याप् 5 P; प्र-सृ 1 P, आयम् pass., प्र-सृ-सृप् 1 P, प्रथ्-वृध् 1 A, वृत् 1 A; 'the age of man e. ed to 10,000 years' दशसहस्रवर्षायुषो नरा आसन्; 'e. as far as' ex. by आ with abl. or in comp.; 'whose sovereignty of the earth e. ed as far as the sea' आसमुद्रक्षितीशानां (R. I. 5). **-Extension,** *s.* विस्तारः, विततिं *f.*, विस्तृति *f.*, आयामः, प्रसारणं, प्रसरः, व्याप्ति *f.*, विस्तीर्णता. **2** वृद्धि *f.*, प्रपंचः, विपुलता. **-Extensive,** *a.* विस्तीर्ण, विपुल, प्रचुर, विशाल, पृथु, आयत, असंबाध, महत्. **2** व्यापक, व्यापिन्. **-ly,** *adv.* बहुशः, प्रचुरं, अतीव, अतिमात्रं, बाहुल्येन, भूयसा. **-ness,** *s.* विस्तारः, &c. **-Extent,** *s.* विस्तारः, आयामः, आभोगः, विशालता, आयति *f.*, परिणाहः. **2** परिमाणं, प्रमाणं; 'the city is 100 yojanas in e.' विस्तीर्णा योजनशतं पुरी; 'to a great e.' अतिमात्रं, अतीव; 'to some e.' कियतांऽशेन, स्तोकं, ईषत्, मनाक्; 'to such e.' एतावत्, इयत्; 'to the fullest e.' सर्वांशेन, सर्वथा; 'to what e.' कियत्प्रमाणं, कियत्पर्यंतं.

Extenuate, *v. t.* **Emaciate,** q. v. **2** लघयति (D.), कृश् 10, न्यून् c., अल्पीकृ 8 U, लघूकृ, शम् c. (शमयति); मृदू 10, संक्षि

2 P (a crime &c.). **-ion,** *s.* उपशमः, लघूकरणं. **2** पापमार्जनं-प्रक्षालनं.

Exterior, *a.* बाह्य, बहिःस्थ, बहिर्भव; gen. ex. by बहिः in comp. **-s.** बहिराकारः, बाह्याकारः, बाह्यरूपं. **2** बाह्यभागः, बहिर्देशः-भागः.

Exterminate,-ion, *See* **Eradicate,-ion.**

Extern, *a.* बहिर्वर्तिन्.

External, *a.* बाह्य, बहिर्भव, बहिःस्थित-वर्तिन्, बहिः in comp.; 'without e. aid' विना बाह्यसाधनं, बाह्योपाधिं विना. **-ly,** *adv.* बहिः, बाह्यतः.

Extinguish, *v. t.* निर्वा c. (वापयति); प्र-उप-शम् c. (शमयति) (as thirst &c.). **2** वि-नश् c., वि-लुप् c., अव-उत्-सद् c., उच्छिद् 7 P. **-ed, -Extinct,** *a.* शांत, निर्वापित, निर्वाण. **2** नष्ट, उच्छिन्न, लुप्त, निर्गत, क्षीण, अवसन्न, निवृत्त; 'his family became e.' स निर्वंशो जातः; 'almost e.' निर्वाणभूयिष्ठ; 'to become e.' शम् 4 P, निर्वा 2 P. **-ment, -Extinction,** *s.* निर्वाणं, निर्वापणं. **2** उच्छेदः, विलोपः, विनाशः, संहारः, क्षयः; 'final e.' निर्वाणं; मोक्षः; 'e. of family' कुलोच्छेदः, निर्वंशता.

Extirpate, *See* **Eradicate.**

Extol, *v. t.* वर्ण् 10, कृत् 10, प्रशस् 1 P, श्लाघ् 1 A, स्तु 2 U, प्र-वि-ख्या 2 P; *See* **Praise. -ler,** *s.* प्रशंसकः, स्तावकः.

Extort, *v. t.* बलात्-अन्यायेन आदा 3 A or ग्रह् 9 U, दा c. (दापयति), आहृ c., निष्कुष् 1 P, बाधित्वा ग्रह्; बाध् 10, उपपीड् 10 **-er, -ioner,** *s.* बलेन परस्वापहारकः, बाधकः, औपधिकः, उपपीडकः, उपद्रविन् *m.* **-ion,** *s.* बलादादानं, अन्यायेन परस्वापहरणं, उपद्रवः, बाधः-धा, बलात्कारः, विप्लवः. **2** हठः, चलं; 'by e.' बलात्, अन्यायेन, प्रसभं, प्रसह्य.

Extra, *a,s.* अधिक, अतिरिक्त, अति pr.; (in comp.) ex. by व्यतिरिक्त, भिन्न, अधिक, अतिरिक्त.

Extract, *v. t.* निष्कृष् 1 P, आकृष्, निः-उद्-हृ 1 P, उद्-ग्रह् 9 P; निर्दुह् 2 U, निष्कुष् 9 P, निः-सं-पीड् 10 (by squeezing); निर्गम् c. (गमयति), उत्पद् c. **-s.** रसः, निर्यासः, निर्यूहः, कषायः, निष्कर्षः, उद्धारः **2** सारः, संग्रहः, संक्षेपः, उद्धृतभागः, निष्कर्षः, पिंडितभागः. **-ion,** *s.* निष्कर्षः-र्षणं, उद्धरणं, निर्हरणं. **2** कुलं, वंशः, उत्पत्ति *f.*, अन्वयः, जन्मन् *n.*, संभवः, उद्भवः; 'of high e.' अभिजात, महाकुल, कुलीन; 'of royal e.' राजवंश्य, राजकुलप्रसूत.

Extra-judicial, *a.* व्यवहारविषयातिक्रांत.

Extra-mundane, *a.* अतिसंसार, लोकबाह्य

Extra-mural, *a.* दुर्गबहिर्वर्तिन्.

Extraneous, *a.* बाह्य, बहिर्भव. **2** भिन्न असंगत, व्यतिरिक्त, विदेशीय, असंबद्ध.

Extraordinary, *a.* असाधारण (णी *f.*), लोकोत्तर, असामान्य, अलोकसामान्य, अपूर्व, अद्भुत, चित्र, अदृष्टपूर्व, विलक्षण, आश्चर्य. **-ly,** *adv.* अपूर्वं, अद्भुतं, चित्रं. **-ness,** *s.* वैलक्षण्यं, आश्चर्यत्वं, लोकोत्तरता.

Extravagant, *a.* अतिव्ययपर, अतिमुक्तहस्त, व्ययशील, अमितव्यय, अतिव्ययिन्. **2** अनियंत्रण, अमर्याद, अपरिमित, मर्यादातिक्रामिन्, उत्क्रांतमर्याद. **-ly,** *adv.* अतिव्ययेन, मुक्तहस्तेन. **2** अतिमात्रं, सातिशयं, अमितं. **-Extravagance,** *s.* अति-अमित-व्ययः, मुक्तहस्तः, धनोत्सर्गः, व्ययापरिमितता. **2** मर्यादातिक्रमः, अतिक्रमः, अतियशः, अमितता, अत्याचारः, नियमोल्लंघनं

Extravasated, *a.* शिरा-नाडि-बहिर्गत. **-Extravasation,** *s.* (Of blood) रक्तमोक्षणं, रक्तनिर्गमः

Extreme, *a.* पर, परम, निरतिशय, अत्यंत, महत्, अति pr.; 'e. limit'; परमावधिः. **2** बाह्य. **3** अंत्य, अंतिम, शेष in comp. **-s., -ity,** *s.* पराकोटि *f.* -काष्ठा, अत्यंतता, अतिभूमि *f.*, परमावधिः, अतिशयः. **2** अंतः-तं, पारः, पर्यंतः, अग्रं, प्रांतः, सीमन् *f.*; अवधिः, उत्तमावधिः; 'this is the e. of delightful things' इयं प्रीतिजननानां सीमांतलेखा-परिसमाप्तिः-अवसानभूमिः (Ka. 124); 'e.s are ever bad' अति सर्वत्र वर्जयेत्. **3** विषमावस्था, अतिकृच्छ्रं, अत्यंतक्लेशः-दुःखं, दुःस्थिति *f.*, दुर्दशा, कष्टावस्था. **-ly,** *adv.* अत्यंतं, अतिभृशं; *See* **Exceedingly.**

Extricate, *v. t.* उद्धृ 1 P, मुच् 6 P or c., मोक्ष् 10, परि-,त्रै 1 A, रक्ष् 1 P, सं-उत्-निः-तॄ c. **-ion,** *s.* उद्धारः, विमोचनं, मुक्ति *f.*, मोक्षः-क्षणं, निस्तारः, त्राणं, रक्षणं.

Extrinsic,-al, *a.* बाह्य, बहिर्भव, असहज, आगंतुक (की *f.*). **-ally,** *adv.* बाह्यतः, असहजं.

Extrude, *v. t.* उत्सृ c.; *See* **Drive.**

Extuberance, *s.* अधिमांसं, गंडः, स्फोटः, श्वयथुः.

Exuberant, *a.* प्रचुर, बहुल, समृद्ध, स्फीत, परिपूर्ण, उद्रिक्त, अतिरिक्त, भूरि, पुष्कल, उत्सिक्त. **-ly,** *adv.* प्रचुरं, बहुशः, बाहुल्येन.

Exuberate, *v. i.* प्रचुरीभू 1 P, वृध् 1 A, समृध् 5 P **Exuberance,** *s.* प्राचुर्यं, समृद्धि *f.*; स्फीति *f.*; उद्रेकः, उपचयः, वृद्धि *f.*, अतिशयः, आधिक्यं; 'in e. of joy' हर्षनिर्भरं.

Exude, *v. i.* प्र-स्नु 2 P, स्विद् 1 A, 4 P; स्वेद इव प्र-स्रु 1 P or निस्यंद् 1 A. **-v. t.** (स्वेदं) निःसृ c. or निःस्रु c. **2** उद्-भू 6 P, उद्गम् 1 P, निष्ठिव् 1, 4 P. **-ation,** *s.* प्र-

स्रवः, स्वेदः, स्वेदस्रावः. 2 स्रवः-वणं, स्यंदनं निर्यासः, स्रावः. 3 निष्ठीवनं, उद्गारः, उद्वमनं.

Exulcerate, *v. t.* व्रणं उत्पद् c., क्षतं कृ 8 U; क्षण् 8 P. **-ion,** *s.* व्रणोत्पत्ति *f.*, क्षतोत्पादनं.

Exult, *v. i.* प्र-मुद् 1 A, उत्सिच् pass, अत्यंतं आनंद् 1 P or हृष् 4 P or उल्लस् 1 P. **-ant,** *a.* उत्सिक्त, प्रमुदित, परमहृष्ट, उल्लसित, सगर्व, उन्मत्त, सदर्प. **-ation,** *s.* प्रमोदः, उत्सेकः, उल्लासः, परमानंदः, परमाह्लादः, परमहर्षः, मदः, गर्वः, अवलेपः. **-ing,-ly,** *adv.* सप्रमोदं, सोल्लासं, सोत्सेकं, सगर्वं, सदर्पं.

Exuviae, *s.* निर्मोकः.

Eye, *s.* चक्षुस् *n.*, वि-,लोचनं, नेत्रं, नयनं, अक्षि *n.*, दृश् *f.*, दृष्टि *f.*, ईक्षणं-णा, दृशा. 2 (View) दृष्टि *f.*; 'in the e. s of the public' लोकदृष्ट्या. 3 रंध्रं, छिद्रं. 4 **Bud,** q. v.; 'corners of the e.' अपांगः-गं, नयनोपांतः. 'mind's e.' ज्ञानचक्षुस् *n.*, मनोमयं ज्ञानं; 'before one's e. s' समक्षं, साक्षात्, प्रत्यक्षं-क्षतः; oft. by पश्यत्; 'before my very e. s' पश्यतोपि मम; 'in my e. s' मम दृष्ट्या, मां प्रति. **-v. t.** निरीक्ष् 1 A, आ-अव-लोक् 1 A, 10, दृश् 1 P; *See* **See,** 'e. pupil' तारा, कनीनिका, तारका; 'e. beam' नयन-दृष्टि-पातः; 'e.-drop' नेत्रजलं, बाष्पाम्बुः, अश्रु *n.*; 'e.-brow' भ्रूः, भ्रू ऽ त; 'e.-glass' उपनेत्रं-नयनं; 'e.-lash' पक्ष्मन् *n.*; 'e.-let, e.-hole' गवाक्षः, छिद्रं, रंध्रं; 'e.-lid' नेत्र-नयन-च्छदः; 'e. reach (shot)' चक्षुर्विषयः, नयनगोचरः-रं, दृक्पथः; 'e.-sore' अक्षिशूलं, चक्षुःपीडा; अक्षिगतः, द्वेष्यः; 'I am an e. sore to him' अक्षिगतोहमस्य; 'e.-wink' नयनसंज्ञा-संकेतः, कटाक्षः, 'e. witness' प्रत्यक्षसाक्षिन् *m.*, दर्शिन् *m.*, साक्षाद् द्रष्टृ *m* **-less,** *a.* चक्षुर्हीन, अनयन, दृष्टिविकल. 2 अच्छिद्र.

Eyot, *s.* लघुद्वीपं.

F

Fable, *s.* कथा, आख्यायिका, उपाख्यानं, कल्पितकथा, पुरावृत्ताख्यानं, प्रबंधकल्पना. **-v. t.** मनसा कल्प् c. or रच् 10 or सृज् 6 P. **-Fabulous,** *a.* ऐतिहासिक (की *f.*), कथानिबद्ध, आख्यानकीर्तित. 2 अलीक मनःकल्पित, मनसा सृष्ट, काल्पनिक (की *f.*,) कृत्रिम. **-Fabulist,** *s.* कथारचकः, ऐतिहासिकः.

Fabric, *s.* भवनं, गृहं, हर्म्यं, मंदिरं, प्रासादः, धामन् *n.*, शाला. 2 निर्माणं, रचनं. 3 कृति *f.*, पटाकारः. 4 **Cloth,** q. v. **-Fabricate,** *v. t.* निर्मा 3 A or 2 P or c. (मापयति), विरच् 10, कृ 8 U, क्लृप् c., वि-धा 3 U, सृज् 6 P. 2 मनसा सृज् or क्लृप् c., कपटेन-मिथ्या क्लृप् c.; 'to f. evidence' कूटप्रमाणं निर्मा, कपटसाक्ष्यं कृ; *See* **Counterfeit. -ion,** *s.* कपटरचना, अलीकं, कृत्रिमनिर्माणं मनःकल्पना, कूटं. 2 निर्माणं, कल्पना-नं, रचना. **-or,** *s.* [illegible]तृ *m.*, रचकः. 2 कूटकृत् *m.*

Façade, *s.* हर्म्यमुखं.

Face, *s.* मुखं, वदनं, आननं, वक्त्रं, आस्यं, तुंडं. 2 तलं, पीठं, पृष्ठं. 3 अवस्था, स्थिति *f.*, दशा; 'before one's f.' अग्रे, अग्रतः, पुरतः, समक्षं, प्रत्यक्षं, संमुखं-खे. 'long f.' विषण्णवदनं; 'f. to f.' मुखामुखि, संमुखं; 'in the f. of ' अनादृत्य, अविगणय्य; *See* 'in spite of; 'in the f. of so many difficulties' एवंविधान्यपि कृच्छ्राण्यविगणय्य; 'turn away the f.' विमुखीभू; 'stand f. to f.' संमुखी-अभिमुखी-भू. **-v. t.** संमुखयति-अभिमुखयति (D.); प्रतिमुखी-संमुखी-अभिमुखी-भू 1 P, (with gen.), संमुखं स्था 1 P, अभिमुखं गम् 1 P; पर्यव-स्था 1 A. 2 संमुख-अभिमुख-प्रतिमुख. **-a.** भू 1 P, or by मुख-अभिमुख in comp.; 'a house f.-ing the east' पूर्वाभिमुखं गृहं; 'stand f.-ing the east' प्राङ्मुखस्तिष्ठ; 'one who boldly f. s the enemy' अभ्यमित्र्यः; अभ्यमित्रीणः-यः. **-ed,** *a* (*s*) in comp.; 'moon-f.' चंद्रानना, इंदुमुखी. 2 पटाकृत, अधिवस्त्रान्वित. **-less,** *a.* निर्मुख, आननहीन.

Facet, *s.* कणः, मुखं.

Facetious, *a.* विनोदिन्, परिहासशील, नर्मप्राय, सरस, रसवत्, हासोत्पादक, नर्म in comp. **-ly,** *adv.* सरसं, विनोदार्थं, परिहासपूर्वं. **-ness,** *s.* परिहासशीलता.

Facile, *a.* सुकर, सुसाध्य, अनायास; *See* **Easy.** 2 अनुकूल, अनुवर्तिन्. **-ity,** *s.* **Ease,** q. v. 2 लाघवं; 'f. of hand' हस्तलाघवं, क्षिप्रता, सहजता. **-Facilitate,**

v. t. सुकर *a.* कृ 8 U, विघ्नान् अपनी 1 P, or नश् c., निर्विघ्नीकृ; better ex. by words for 'Easy' q. v.; 'this will f. their communication' अनेन तेषामन्योन्यव्यवहारोऽयत्नसाध्यो भवेत्-सुकरो भवेत्. **-ed,** *a.* निर्विघ्न, हस्तस्पृष्ट, सुकरीकृत.

Facsimile, *s.* प्रतिलिपि *f.*, प्रतिरूपं.

Fact, *s.* तथ्यं, यथार्थता, सत्यं, तत्त्वं, भूतार्थः; 'it was a statement of f. s' भूतार्थव्याहृतिः सा (R. x. 33). **2** वृत्तं, वस्तु *n.*, अर्थः, कर्मन् *n.*; 'in fact' वस्तुतः, तत्त्वतः, 'as a matter of f.' वस्तुवृत्तेन, परमार्थतः, तत्त्वतः.

Faction, *s.* दलं, पक्षः, शाखा. **2** भेदः, विरोधः, विप्रतिपत्ति *f.*, द्वंद्वं, द्वैधं, पक्षभेदः. **-Factious,** *a.* कलहप्रिय, भेदकारिन्, उपजापिन्, उपजापक, भेदिन्. **2** पाक्ष (क्षी *f.*). **-ly,** *adv.* सोपजापं. **-ness,** *s.* उपजापः, भेदकारिता.

Factitious, *a.* कृत्रिम, कृतक, कल्पित, रचित, शिल्पनिर्मित.

Factor, *s.* नियोगिन् *m.*, प्रतिनिधिः; 'three is a f. of six' षट् त्रिभिर्भाज्याः.

Factory, *s.* शिल्प-कर्म-शाला-गृहं, पण्यनिर्माणस्थानं.

Factotum, *s.* सर्वकर्मकरः.

Faculty, *s.* शक्ति *f.*, क्षमता, प्रभावः, सामर्थ्यं. **2** अधिकारः. **3** गणः, समाजः.

Fad, *s.* लहरी, छंदः.

Fade, *v. i.* म्लै-ग्लै 1 P, वि-क्षि pass., निर्मल् 1 P, विच्छायतां व्रज् 1 P, विवर्णीभू 1 P. **2** अवसद् 1 P, जृ 4 P, नश् 4 P, क्षि pass., ध्वंस् 1 A, प्र-ली 4 A, अप-चि pass **-v. t.** Causal of roots above. **2** तेजो हृ 1 P, वर्णं नश् c. or विलुप् c., विवर्णीकृ 8 U. **-ed,** *a.* नष्ट, क्षीण, अपचित. **2** म्लान, विवर्ण, विच्छाय, गतवर्ण, वीतराग. **-ing,** *s.* म्लानि *f.*, क्षयः, ध्वंसः, अवसादः, हानि *f.*; 'f. of colours' वर्णोच्छेदः, वर्णहानिः, वर्णिकोच्छ्रासः.

Fag, *s.* दासः, निरंतरायासिन् *m.*, श्रांतीमः. **-v. i. Drudge,** q. v.

Fag end, *s.* अंतः, अवसानसमयः. **2** शेषः-षं, उच्छिष्टं, अवशेषः.

Fagot, *s.* काष्ठानि (pl.); दारुखंडः, काष्ठभारः, इंधनदारु *n.*

Fail, *v. i.* अव-वि-सद् 1 P, ध्वंस् 1 A, नश् 4 P, विलुप् pass., क्षि pass ; 'whose talent f. s not in difficulties' संकटेष्वविषण्णधीः. **2** भग्नाश *a.* भू 1 P; (of efforts) व्या-प्रति-हन् pass., व्यर्थ-मोघ-*a.* भू, न सिध् 4 P, विफलीभू. **3** प्रमद् 4 P (with abl.), (स्वाधिकारात् प्रमत्तः Me. 1); विस्मृ 1 P, उपेक्ष् 1 A, न अनुष्ठा 6 A. **4** न्यूनीभू, क्षि-अपचि pass. **5** विसं-वद् 1 P; 'f. s to give the fruit' फले विसंवदति (V. 2);

'a good appointment was made to f. by Fate' रमणीयोऽयमविधिविधिना विसंवादितः (S. 6). **-v. t.** त्यज् 1 P, हा 3 P; 'whose courage does not f. him' यस्य धैर्यं न हीयते, न स्खलति; 'f. ing male issue' पुत्राभावे; 'his memory f. ed him' तस्य स्मृतिलोपः संजातः. **-s.** उपेक्षा, अननुष्ठानं; 'without f.' अवश्यं, नियतं, ध्रुवं, सुनिश्चितं, असंदेहं. **-ing,** *s.* दोषः; अपराधः, अगुणः, छिद्रं, न्यूनता, वैकल्यं. **-a.** मोघ, व्यर्थ; 'un-f. source' अक्षयः प्रभवः. **-ure,** *s.* अभावः, विरहः, लोपः, हानि *f.*, न्यूनता, वैकल्यं. **2** भंगः, अनिष्पत्ति *f.*, असिद्धि *f.* **3** अवसादः, क्षयः, ध्वंसः, नाशः, भ्रंशः, उच्छेदः, ह्रासः, क्षीणता, लोपः; 'f. of issue' संततिच्छेदः. **4** उपेक्षा-क्षणं, अननुष्ठानं, प्रमादः, उपात्ययः, अतिपातः, व्यतिक्रमः, लोपनं

Fain, *adv.* प्रकामं. सकामं, सानंदं; *See* **Gladly.**

Faint, *a.* अवसन्न, क्षीण, दुर्बल, अशक्त, शिथिलबल, निःसत्त्व, विकल, म्लान, ग्लान, क्लांत, खिन्न, तांत, विषण्ण; श्रांतांग (गी *f.*), शुष्कगात्र, स्रस्तांग. **2** अस्पष्ट, अस्फुट, मंद. **3** (As colours) पांडु, विवर्ण, मंदप्रभ, मंदच्छाय; oft. by ईषत् or आ pr.; 'f. red' आरक्त, ईषद्रक्त; 'f.-hearted' भीरु, कातर, कापुरुष. **-v. i.** मुर्छ् 1 P, मुह् 4 P, मोहं-मूर्छां-गम् 1 P or आप् 5 P, चेतना-संज्ञां-हा 3 P, नष्टचेतन-लुप्तसंज्ञ-*a.* भू 1 P. **2** ग्लै-म्लै 1 P, संस् 1 A, वि-अव-सद् 1 P, क्लम् 1, 4 P, तम् 4 P. **3** प्र-ली 4 A, नश् 4 P, क्षि pass. **-ing,** मूर्छा, मोहः, प्र-सं-मोहः, चैतन्य-संज्ञा-लोपः-नाशः, प्रलयः, चेतनानाशः. **-ly,** *adv.* स्तोकं, अल्पं, ईषत्, मनाक्; मंदं, अल्पबलेन. **-ness,** *s.* म्ला-ग्ला-नि *f.*, अवसादः, क्षीणता; वैवर्ण्यं, &c

Fair, *a.* चारु, सुंदर (री *f.*), शोभन ; *See* **Beautiful:** ex. by सु in comp.; 'the f. sex' स्त्रीजनः. **2** सम, न्याय्य, युक्त, उचित, धर्म्य, यथान्याय, न्यायवर्तिन्, शुचि, ऋजु, निर्व्याज, निष्कपट; विमलात्मन्, शुद्धधी; 'a f. fight' धर्मयुद्धं. **3** विमल, निर्मल, शुद्ध, विशद, स्वच्छ; गौर, शुभ्र (complexion); अनभ्र, निरभ्र, वितिमिर ; 'f. day or weather' सुदिनं. **4** अनुकूल, प्रसन्न. **5** मध्यम; 'he soon bids f. to prosper' तेनाचिरादभ्युदयभाजा भवितव्यमित्यनुमीयते. **-s.** मेला, मेलकः, यात्रा, समाजः; हट्टः, निषद्या, निगमः. **-adv.**, **-ly,** *adv.* न्यायेन, यथान्यायं, धर्मतः, धर्मेण, निष्कपटं, न्याय्यं, यथार्हं. **-ness,** *s.* सौंदर्यं, चारुता, श्रीः, शोभा. **2** (Fair dealing) सारल्यं, शुचिता, न्याय्यता आर्जवं, अपक्षपातः, समता, अमाया. 3 निर्मलता शुद्धि *f.* प्रसादः

Fairy, *s.* विद्याधरी, पिशाची, योगिनी, राक्षसी.

Faith, *s.* विश्वासः, प्रत्ययः, विश्रंभः 2 श्रद्धा, भक्ति *f.*, निष्ठा, आस्तिक्यबुद्धि *f.* 3 अव्याजः, ऋजुता, सत्यता, विश्वास्यता. **-ful,** *a.* विश्वास्य विश्वसनीय, विश्रब्ध. 2 सत्यसंध, सत्यप्रतिज्ञ-व्रत; 'f. to promise' पालितसंगर, प्रतिज्ञापालक. 3 अनुरक्त, भक्त, दृढभक्ति, भक्तिमत्; 'a f. wife' साध्वी, एकपत्नी, पतिव्रता, सती, सुचरित्रा; 'a f. friend' दृढसौहृदं-दृढप्रेम-मित्रं. 4 यथार्थ, सत्य. 5 श्रद्धालु, श्रद्दधान, प्रत्ययिन्, विश्वासिन्. **-fully,** *adv.* दृढभक्त्या, भक्तिपूर्वं, सानुरागं, निष्ठया; अव्याजं, ऋजुभावेन, निष्कपटं. **-fulness,** *s.* विश्वास्यता. 2 भक्ति *f.*, दृढा भक्तिः, अनुरक्ति-आसक्ति-*f.*; आर्जवं, निष्कापट्यं. 3 प्रतिज्ञापालनं, सत्यसंधता. 4 सत्यता. **-less,** *a.* अविश्वास्य. 2 अभक्त, विश्वासघातक, भक्तिहीन, अननुरक्त. 3 असत्यसंध, भग्नप्रतिज्ञ, विसंवादिन्. 4 अविश्वासिन्, अप्रत्ययिन्, अश्रद्दधान. 5 व्यभिचारिन्; असती, असाध्वी, भ्रष्टचारित्र्या (as a woman). **-lessness,** *s.* अविश्वासः, अप्रत्ययः, अश्रद्धा. 2 विश्वासभंगः-घातः, अभक्ति 3 *f.* प्रतिज्ञाभंगः, समयव्यतिक्रमः, असत्यसंधता, व्रतलोपनं.

Falcated, *a.* वक्र, खड्गाकृति.

Falchion, *s.* वक्रखड्गः, निस्त्रिंशः, चंद्रहासः, कृपाणः.

Falcon, *s.* श्येनः, शशादनः, पत्रिन् *m.*, खगांतकः. **-er,** *s.* श्येनपालकः-पोषकः, श्येनाजीवः. **-ry,** *s.* श्येनपालनं-शिक्षा-पोषणं.

Fall, *v. i.* च्यु 1 A, भ्रंश् 1 P, स्रंस् 1 A, पत् 1 P, नि-अव°, भ्रंश् 1 A, 4 P; 'fell under his displeasure' तस्याकृपापात्रं-कोपास्पदं बभूव. 2 मृ 6 A, नश् 4 P, वि-प्र-ध्वंस् 1 A, प्र-ली 4 A, प्राणैः वियुज् pass. 3 अवसद् 1 P, क्षि-अपचि pass., न्यूनीभू 1 P, ह्रस् 1 P; 'a cow f. s beneath his paw' गौस्तस्य नखपंजरे पतति, नखराक्रांता भवति; 'when the wind fell' शांते पवने. 4 द्रु 1 P, प्रविश् 6 P, अवतॄ 1 P, (गंगा सागरं प्रविशति-अवतरति); 'f. foul of' संघट्ट 1 A, आक्रम् 1 U, 4 P; वि-वद् 1 A; 'f. to the ground' ध्वंस्, (ध्वंसितस्ते उत्साहवृत्तांतः S. 2), विनश् **-s.** पातः, पतनं, च्युति *f.*; ध्वंसः, भ्रंशः, स्रंसनं, अधः-नि-पतनं, अव-नि-पातः; 'in rapid f. descend' जवेन निपतंति. 2 स्थानभ्रंशः-च्युतिः, अपकर्षः, पदनाशः-भ्रंशः-च्युतिः. 3 प्र-वि-ध्वंसः, सं-उप-परि-क्षयः, अवसादः; 'rise and f.' पातोत्पाताः. 4 ह्रासः, अपचयः, न्यूनीभावः. 5 निर्झरः, प्रस्रवणं, प्रपातः, वारिप्रवाहः. 6 पातुकप्रवण-भूमि *f.*; 'f. of snow' तुषारवर्षः, हिमवृष्टि *f.*, 'f. of rain' धारासंपातः, धारासारः, आसारः. **-away,** म्लै ग्लै 1 P. निर्बल्, प्र-क्षी, नश्. 2 स्वधर्मात् भ्रंश् or च्यु. **-back,** परावृत् 1 A, अप-सृ-सृप् 1 P, अवस्था 1 A. **-in with,** संमन् 4 A, अभ्युपगम् 1 P; *See* Agree. 2 आसद् *c.*, सहसा दृश् 1 P. **-into,** नि-अंतः-पत्; 'f. into vice' कुमार्गगामिनो भवंति; 'f. into misfortune' विपद्ग्रस्ता भवंति **-off,** च्यु भ्रंश्. 2 अपसृ 1 P, पलाय् 1 A, वियुज् pass. 3 स्वधर्मं त्यज् 1 P, पत्. 4 ह्रासं गम् 1 P, क्षि-अपचि-संहृ -pass., ह्रस्. **-on, -upon,** आक्रम्, अभिद्रु, आपत्, अवस्कंद् 1 P. **-out,** विवद् 1 A, विप्रति-पद् 4 A, कलहं कृ 8 U. **-short,** न्यूनीभू, ह्रस्, क्षि-संहृ pass.; 'his arrow fell short of its aim' स लक्ष्यच्युतसायकोऽभूत्; 'words f. short in describing your greatness' तव महिमानमुत्कीर्त्य वचः सान्द्रियते (R. x. 32). **-to,** प्र-उप-क्रम् 1 A, प्रारभ् 1 A; 'they fell to blows' परस्परप्रहारमारेभिरे. **-under,** (power) वशं इ 2 P, अधीन *a.* भू. 2 अंतर्भू, अंतर्गण् pass.

Fallacy, *s.* वंचना, भ्रमः, मोहः, भ्रांति *f.*, मिथ्याज्ञानं, हेत्वाभासः, पक्षाभासः, मिथ्याहेतुः. **-ous,** *a.* भ्रमजनक, भ्रांतिमत्, मोहिन्, मायिन्; असत्य, अविश्वास्य, मिथ्या in comp.; 'a f. argument' हेत्वाभासः. **-ously,** *adv.* मिथ्या, सव्याजं, मायया.

Fallible, *a.* पतन-स्खलन-शील, भ्रमशील, भ्रमाधीन, मोहशील, भ्रम-स्खलन-पात्रं. 2 भ्रमकारिन्, मोहिन्, मोहजनक. **-Fallibility,** *s.* भ्रमपात्रता, मोहशीलता, स्खलनशीलं

Fallow, *a.* अकृष्ट, अहल्य, अप्रहत, खिल. 2 वंध्य, निष्फल, विफल, अशस्य 3 ईषद्रक्त, आरक्त, श्वेतरक्त.

False, *a.* असत्य, अनृत, वितथ, अतथ्य, अयथार्थ, अलीक, मृषा-मिथ्या- in comp.; 'f. speech' मृषोद्यं. 2 कृत्रिम, कृतक, कल्पित, कूट-कपट-छद्म- in comp.; 'f. balance' कूटतुलामानं; 'f. ascetic' छद्मतापसः, बकव्रतः; 'f. witness' कूट-मिथ्या-साक्षिन् *m.*; 'f. accusation' मिथ्याभियोगः, अभिशापः, अभ्याख्यानं, मिथ्याभिशंसनं. 3 कापटिक (की *f.*), विश्वासघातिन्, मंत्र-रहस्य-भेदिन्; 'f. to one's promise' लुप्तप्रतिज्ञ, असत्य-संध, भग्नप्रतिज्ञ-व्रत. 4 मायिन्, दंभिन्, दांभिक-छाद्मिक (की *f.*). 5 मोघ, व्यर्थ, निरर्थक, वृथा-मिथ्या- in comp. **-hood,** *s.* अनृतं, असत्यं, वितथं, अलीकं, मृषोद्यं, कैतवं. 2 असत्यभाषणं, मिथ्या-मृषा-वादः, कैतवोक्ति *f.*, मिथ्याभिधानं, अनृतवादः. 3 असत्यता, अलीकता, अयथार्थता, अनृतता. **-ly,** *adv.* मृषा, मिथ्या, अन्यथा, असत्यं, अनृतं; 'speaking f.' अनृतवादिन्. **-ness,** *s.* असत्यता, &c. 2 कूटता, कापट्यं, व्याजः, छद्मन् *n.*, कैतवं. 3 विश्वासभंगः-घातः. **-Falsify,** *v. t.* मिथ्या कृ 8 U, कूट-कपटं-कृ

'a f. ed document' कूट-कृत्रिम-लेखः. **2** खंड् 10, मिथ्या-अन्यथा-कृ, अयथीकृ, वितथीकृ, प्रत्या-ख्या 2 P, निरस् 4 U. **3** अतिक्रम् 1 U, 4 P, अतिवह् 1 P, भिद् 7 P, उल्लंघ् 1 A. 10, वि-,लुप् 6 P, or c. —*v. i.* असत्यं-अनृतं-वद् 1 P. **—er,** *s.* कूटकृत् *m.*, कूटकः 2 अनृतवादिन्-प्रत्याख्यातृ *m.* **—ication,** *s.* कूटकरणं-रचना, मिथ्याकरणं.

Falter, *v. i.* (स्वरेण) स्खल् 1 P, स्वरभंगेन or सगद्गदं-वद् 1 P 'makes thy words f.' स्खलयति वचनं ते (Mal. 3); 'f. ing with tears' बाष्पगद्गदं; 'a f. ing step' स्खलिता गतिः; प्रस्थानविक्लवगतेः (S. 5); whose step f. s &c.' **2** प्रचल् 1 P, कंप् 1 A. वेप् 1 A. प्रस्खल्. **—ing,** *s.* स्खलनं, स्वरभंगः-भेदः, गद्गदवाच् *f.*, स्खलद्वाक्यं. **—ingly,** *adv.* गद्गदगिरा. स्खलद्वाचा, स्वरभंगेन. सगद्गदं

Fame, *s.* यशस् *n.*, कीर्ति *f.*, ख्याति *f.*, विश्रुति प्रसिद्धि *f.*, प्रतिष्ठा, प्र-वि-ख्यातिः, संप्रथा **—ed, —ous,** *a.* ख्यात, प्रथित, विश्रुत, प्र वि-ख्यात, प्रसिद्ध, यशस्विन्, यशस्वत्, कीर्तिमत्, कीर्तित, लोकविश्रुत, महायशस्क, लब्धप्रतिष्ठ-वर्ण.

Familiar, *a.* परिचित, संस्तुत, अभिज्ञ; अविद्-कुशल-in comp.; अभ्यंतर, (अनभ्यंतरे खलु भवान् मदनवृत्तान्तस्य S. 3.). **2** सुविदित, सुज्ञात, लोकसिद्ध, प्राकृत, लौकिक (की *f.*), सुप्रसिद्ध, सुप्रकाश. **3** विश्रब्ध, विश्रंभ in comp. **4** निरादर, निर्गौरव, आदुर्वृत्त, निःप्रश्रय. **—ity,** *s.* सु-, परिचयः परिज्ञानं, संस्तवः; 'long f.' चिरपरिचयः; **2** सु-हृद्-संसर्गः, आसंगः, संसक्ति *f.* **3** अतिपरिचयः, अनादरः; 'f. breeds contempt' अतिपरिचयादवज्ञा (भवति) **—ize,** *v. t.* परिचय कृ 8 U, or c. अभ्यस् 4 U or c.; परिचि... (*a.*), परिचितविविक्तेन मनसा (S. 5) 'with a mind f. ed to seclusion.' **—ly,** *adv.* सुपरिचितवत्, सुविश्रब्ध. **2** प्रायः, प्रायशः, लौकिकतया. **3** अनादरेण, निर्गौरवं.

Family, *s.* कुलं, वंशः, जाति *f.*, गोत्रं. **2** कुटुंब, पुत्रकलत्रादि, गृहजनः. **3** अन्वयः, संतानः-नं, संतति *f.*; 'members of a f.' कुटुंबिनः; 'head of a f.' कुटुंबिन् *m.*, कुलपतिः 'of a good f.' कुलीन, महाकुल, अभिजात, कुल in comp., 'his wife is in the f. way' आपन्नसत्त्वा-गर्भवती-जाता; 'of royal f.' राजवंश्य, राजकुलप्रसूत; 'f. dispute' गृहच्छिद्रं, अंतर्भेदः; 'a f. man (diligently caring for the f.)' अभ्यागारिकः ... कुटुंबव्यापृतः.

Famine, *s.* दुर्भिक्षं, अनशनं, दुष्कालः, मन्वंतरः, नीवाक ... आहाराभावः, अन्नाहारासमयः; 'f.-stricken' दुर्भिक्षपीडित.

Famish, *v. t.* (क्षुधया) पीड् 10, अवसद् c., क्षीणी-कृशी-कृ 8 U; 'f. ed with hunger' क्षुत्क्षाम, क्षुत्क्षामकंठ. —*v. i.* अनशनाद् अवसद् 1 P or क्षि pass., क्षाम-कृशीभू ... **—ed,** *a.* क्षुत्क्षाम, क्षुधार्त, क्षुत्पीडित, बुभुक्षित. **—ment,** *s.* बुभुक्षा, अनाहारः, अन्नाभावः, क्षुत्पीडा, क्षुत्क्षामता.

Fan, *s.* तालवृंतः-वृंतकं, व्यजनं, वीजनं, व्यजनः. —*v. t.* वीज् 10, उप-अनु-वी[2]; व्यजनेन विधू 9 U. (fig.) उद्-दीप् c., संधुक्ष् 10.

Fanatic, —al, *a., s.* धर्मोन्मत्त, अतिश्रद्धान्ध; उन्मत्त, भ्रांतबुद्धि. **—ally,** *adv.* उन्मत्तवत्, अतिश्रद्धया. **—ism,** *s.* धर्मोन्मादः, भक्त्युत्कर्षः, अतिभाक्तिकत्वव्रतता. **2** उन्मादः, उन्मत्तता.

Fancy, *s.* वासना, भावना, कल्पना, भावना-कल्पना-शक्ति *f.* **2** बुद्धि *f.*, मति *f.*, संकल्पः. **3** मनोलौल्यं, कामचारः, बुद्धिचापल्यं, चापलं, लहरी, तरंगः, छंदः. **4** रुचि *f.*; अभिरुचिः, कामः; 'to have or take a f. for' स्पृह् 10 (with dat.) or ex. by कामः मनः with inf.; स्पृहयामि खलु दुर्ललितायास्मै (S. 7), 'took a f. to hunt' मृगयां कर्तुमना बभूव. —*v. t.* मन् 4 A, तर्क् 10, सं-वि-भू c.; चिंत् 10, मनसा कल्प् c.; चित्ते-मनसि-कृ, आलोच् 10. **2** रुच् 1 A, अभिनंद् 1 P; 'f. ing oneself to be learned' पंडितंमन्य, पंडितमानिन्; 'doing what one f. es' कामचारिन्. **—Fanciful,** *a.* मानस (सी *f.*), काल्पनिक-मानसिक (की *f.*), मनःकल्पित, भावित, मनोरथसृष्ट-कल्पित, भावनोत्पादित, वासनाकल्पित, संकल्पज, मायामय (यी *f.*) **2** (Of persons) चलचित्त, लोलमति, कामचारिन्, चपलबुद्धि, मनोलौल्यवत्, स्वैरिन्, स्वैरवृत्त. **3** असत्यकल्पनाकृत्, असंभवकल्पक. **—ly,** *adv.* कामचारेण, मनोलौल्यात्, स्वैरं, चापल्येन. **—ness,** *s.* चलचित्तता, लोलमति *f.*, कामचारिता, मनोलौल्यं, बुद्धिचापल्यं, स्वैरिता

Fane, *See* **Temple.**

Fang, *s.* दंष्ट्रा, दशनः-नं, रदः, रदनः, दंतः; 'f. of a serpent' विषदंतः, आशी *f.* **—ed,** *a.* दंष्ट्रिन्, दंतिन्. **—less,** *a.* भग्नदंष्ट्र, निर्दशन, निर्दंत.

Fantasm, *s.* आभासः, माया, मनोरथसृष्टि *f.* **—Fantastic,** *a.* **Fanciful,** q. v. **2** विषम, असंगत, अपरूप, विलक्षण.

Fantasy, *s. See* **Fancy.**

Far, *a.* दूर (with abl. or gen.), विप्रकृष्ट; *See* **Distant;** 'f. from comfort' सुखाद्दूरतः **—adv.** दूरं-रे, आरात् (with abl.), विदूरतः, अत्यंतं, भृशं, अतीव, सु-अति in comp.; 'f. away' दूरे, सुदूरं, 'from f.' दूरात्, दूरतः (नदी,

'how f.' कियद्दूरं, कियत्प्रमाणं, कियत्-प्रमाणं, कियत्पर्यंतं, कियतांतरेण; 'f. off' दूर, दूरस्थ, दूरवर्तिन्, दूरस्थायिन्; 'as f. as' ex. by आ with abl. or in comp.; 'as f. as the sea' आसमुद्रात् or आसमुद्रं; oft. by यावत् (with acc.) or पर्यंत in comp; 'so far as' 'as f. as' इति; *See* under **As** 'not f. from the tree' तस्य वृक्षस्य नातिदूरे; 'by f.' भूयसा; 'your statement is not f. from the truth' भूतार्थकल्पं तव वचः; 'f. gone in love' दूरगतमन्मथा (S. 3). In comp. ex. by अति, बहु, दूर; 'f.-extended' बहुविस्तीर्ण; 'f.-famed' प्रथितयशस्, उरुकीर्ति; 'f.-fetched' क्लिष्ट, यत्नकृत, असुगम, असुकर; 'f.-reaching' दूराधिरूढ; 'f.-seeing', 'f.-sighted' दूरदर्शिन्, दीर्घदृष्टि, दूरदृष्टि.

Farce, *s.* प्रहसनं, दुर्मल्लिका. **–Farcical,** *a.* उपहास्य, हास्य... (री *f.*), हास्योत्पादक; असंगत, अपरूप, हासजनक.

Fardel, *s.* कूर्चः, गुच्छः, स्तबकः, पोटलिका, भारः.

Fare, *s.* अन्नं, आहारः, भक्ष्यं, भोजनं. **2** तार्यं, आतर(त)रः, तारिकं, तरपण्यं-मूल्यं. **–***v. i.* भू 1 P, वृत् 1 A अस् 2 P, स्था 1 P; को वृत्तांतस्तत्रभवत्याः (M. 4) 'how f. s it with her ladyship'; 'f. ing well' सुस्थ, सुस्थित; 'f. ing ill' दुःस्थित, दुर्गत. **–Farewell,** *inter.* स्वस्ति, भद्रं (भूयात्) with dat.; 'bid f.' आमंत्र् 10 A, आप्रच्छ् 6 A.

Farina, *s.* परागः, रजस् *n.*, पुष्परेणु.

Farinaceous, *a.* धान्यमय, गोधूमचूर्णमय (यी *f.*).

Farm, *s.* क्षेत्रं, कृषिक्षेत्रं, क्षेत्रभूमि *f.*; 'f. house' क्षेत्रिकगृहं, क्षेत्रपतिगृहं; 'f. yard' क्षेत्रवाटः-टिका. **–er,** *s.* क्षेत्रपतिः, क्षेत्रपालः, क्षेत्रिकः, क्षेत्राजीवः, क्षेत्रिन् *m.*, कर्षकः, कृषीवलः, कृषिकः. **–ing,** *s.* कृषि *f.*, कृषिकर्मन् *n.*

Farrago, *s.* सन्निपातः, प्रकीर्णकं, संमिश्रणं. **–Farraginous,** *a.* संकीर्ण, संमिश्रित, सम्मिलित.

Farrier, *s.* अश्ववैद्यः-चिकित्सकः. **2** अश्वपादुकाकारः. **–y,** *s.* अश्वचिकित्सा.

Farrow, *s.* शूकरापत्यसमूहः.

Farther, *a.* दूरतर, दवीयस्. **2** अपर; 'the f. end' परः, अपरप्रांतः. **–***adv.* दूरतरं, अधिकदूरं. **2** अग्रे, अग्रतः, परं, पुरतः.

Farthest, *a.* दविष्ठ, दूरतम, सुदूर. **–***adv.* सुदूरं, अतिदूरं-रे.

Farthing, *s.* ताम्रमुद्रा; 'not even a f.' न काकिणी अपि, न किमपि.

Fascia, *s.* बंधनं, वेष्टनं, पट्टः.

Fascinate, *v. t.* मुह् c., अभिमंत्र् 10 A, अभिचर् c., मंत्रबलेन वशीकृ 8 U. **2** हृ 1 P, आकृष् 1 P, प्र-विलुभ् c., ग्रह् 9 P, रम् c. (रमयति). **–ing,** *a.* मोहिन्, हारिन्, हृदयग्राहिन्, मनोहर, चित्ताकर्षिन्, हृदयंगम. **–ion,** *s.* मोहः-हनं, सं-परि-वि-मोहनं, अभिचारः, अभिमंत्रणं, माया, इंद्रजालं, वशक्रिया. **2** आकर्षः, चित्तापहारः, चित्तविलोभनं.

Fash, *v. t.* *See* **Annoy**.

Fashion, *s.* रीति *f.*, प्रकारः, विधिः, विधः, मार्गः; 'f. of dress' भूषाप्रकारः. **2** रूपं, आकारः, आकृति *f.*, मूर्ति *f.*, संस्थानं. **3** लोकाचारः, संप्रदायः, लोकमार्गः-रीतिः, लोकव्यवहारः, लौकिकव्यवहारः, लौकिकाचारः. **–***v. t.* निर्मा 3 A, 2 P, वि-रच् 10, वि-धा 3 U, घट् c. (घटयति), सं-परि-कल्प् c., तक्ष् 1, 5 P, त्वक्ष् 1 P. **2** युज् 7 U, 10 सं-समा धा. **–able,** *a.* लौकिक-व्यावहारिक (की *f.*), लोकाचारानुरूप, लोकव्यवहारानुसारिन्, लोकमार्गानुयायिन्. **–Fashionably,** *adv.* लोकाचारानुरूपं, लोकरीतिवत्.

Fast, *a.* दृढ, गाढ, स्थिर, अचल, स्थावर, निश्चल, स्थायिन्, दृढबद्ध; 'f. friend' दृढसौहृदः; 'f. sleep' गाढनिद्रा, सुनिद्रा. **2** द्रुतगामिन्, त्वरितगति, शीघ्र, जविन्, जवयत, शीघ्रगति. **–***adv.* दृढं, गाढं, स्थिरं; in comp. ex. by दृढ or सु; 'f. bound' सु-दृढबद्ध; 'f. rooted' बद्धमूल, सुरूढ; 'f. asleep' सुखसुप्त, गाढनिद्रां गत. **2** शीघ्रं, आशु, सत्वरं, क्षिप्रं, त्वरितं 'not so f.' अलमलमतिकृतया त्वरया. **–ness,** *s.* दृढता, स्थिरता. **2** दुर्गं, कोटः. **–Fasten,** *v. t.* बंध् 9 P, सं-नि°, वि-नह् 4 U, ग्रंथ् 9 P, (together); संयुज् 7 U, 10, सं-श्लिष् c., सं-धा 3 U, योक्त्रयति (D.). **2** पि-धा 3 U, सं-वृ 5 U, निरुध् 7 U, अर्गलेन बंध्. **3** दृढीकृ 8 U, स्थिरीकृ, संस्तंभ् 9 P or c. **–ing,** *s.* बंधनं-नी, ग्रंथिः. **2** संधि, कुड्मलः.

Fast, *–v. i.* उप-वस् 1 P, आहारात् निवृत् 1 A; 'f. to death' प्रा-यमुपवेशनं कृ 8 U, अनशनेन मृ 6 A. **–***s.*, **–ing,** *s.* उपवासः, अनशनं, अनाहारः, लं-घनं, उपोषणं आमरणं, प्रायः; 'f. ing to death' प्रायोपवेशनं. **–er,** *s.* उपवासकः, कृतोपवासकः.

Fastidious, *a.* दुस्तोषणीय, दुर्ललित, दुराराध्य. **2** सावज्ञ, अवमानिन्, उपेक्षक; 'a f. critic' दोषैकदृश्. **–ly,** *adv.* सावमानं, दुराराध्यतया.

Fat, *a.* पीन, पीवर, पुष्ट, मांसल, आप्यान, स्थूल, स्फीत, मेदस्विन्, पुष्टांग (गी *f.*), स्थूलदेह; 'f. land' उर्वरा. **–** मेदस् *n.*, वसा (सा), वपा, मांसस्नेहः. **–***v. t.* **–ten,** *v. t.*, आ-प्यै *c.*, स्फाय् c. (स्फावयति). सं-वृध् c., पीवरीकृ 8 U, परिपुष् c. **–***v. i.* आ-प्यै 1 A, पीनीभू, संवृध् 1 A, स्फाय् 1 A, उपचि 1 P. **–ness,** *s.* मेदस्विता, पीनता,

स्थूलता, मेदोवृद्धि *f.*, स्फीति *f.* **-ty**, *a.* मांसल, मेदस्विन्.

Fate, *s* दैवं, भाग्यं, भागधेयं, दिष्टं, अदृष्टं, कर्मन् *n.*, नियति *f.*, प्राक्तनं, भवितव्यता; 'personified f.' विधिः, विधाता, कृतांतः, कालः; 'it is our f. to do wrong' पापाचरणं दैवायत्तं-दैवाधीनं. **2** मृत्युः, नाशः, क्षयः, अंतः; गति *f.*, परिणामः; 'he met with a sad f.' शोचनीयः-कष्टः-तस्य अंतः समजायत; 'what was Sitâ's f.' सीतादेव्याः किं वृत्तं (U. 2); 'such has been the f. of your birth' ईदृशस्ते निर्माणभागः परिणतः (U. 4); 'ill-f.' दुर्दैवं, मंदभाग्यं, दैवदुर्विपाकः- विपर्ययः-विपर्यासः. **-ed**, *a.* नियत, दैवनियुक्त, निर्दिष्ट, भवितव्य; 'whose f. time has come' प्राप्तकालः; 'ill-f.' दैवोपहत, दुर्दैव, मंदभाग्य; 'well-f.' भाग्यवत्, धन्य, ससौभाग्य. **-Fatal**, *a.* प्राणहर, प्राणनाशक, जीवितापह, अंतकर, प्राणघातिन्, मृत्युजनक, दुर्विपाक, मर्मभेदिन्. **2** दैव (वी *f.*), नियत, दैवयुक्त, आवश्यक (की *f.*). **-ism**, *s.* दैवपरता, दैवाधीनता. **-ist**, *s.* दैवपरः, दैवायत्तः, दैवपरायणः, दैवाधीनः, यद्भविष्यः, दैवप्रमाणकः. **-ity**, *s.* प्राणहरत्वं; नियतिः, भवितव्यता, अवश्यभावित्वं. **-ly**, *adv.* सनाशं, प्राणांतिकं; 'f. wounded' तया क्षतो यथाऽसंदिग्धो मृत्युः.

Father, *s.* पितृ *m.*, जनकः, जनितृ-जनयितृ *m.*, जन्मदः, तातः; 'f. and mother' पितरौ, मातापितरौ, मातरपितरौ. **2** गुरुः, पूज्यः; 'f. in-law' श्वशुरः; 'f. land' जन्म-पैतृक-भूमि *f.* —*v. t.* स्वीकृ 8 U, परिग्रह् 9 P. **2** आ-रुह् c. (रोपयति), निविश् c., (with loc.). **-hood**, *s.* पितृभावः-धर्मः, पितृत्वं. **-less**, *a.* अपितृक, तात-पितृ-हीन, अनाथ. **-ly**, *a.* तात-पितृ-तुल्यं, पितृनिर्विशेष, gen. by comp.; 'f. affection' पितृवात्सल्यं. —*adv.* पितृवत्, तातरूपेण.

Fathom, *v. t.* (तलं or वेधं) परीक्ष् 1 A, निरूप् 10, मा 3 A or c. (मापयति), व्यध् 4 P; 'f. another's thoughts' मनः परीक्ष् or ग्राह् 1 A or निरूप्. —*s.* व्यामः, व्यायामः. **-less**, *a.* अगाध, अतलस्पर्श, अनवगाह्य, अगम्यतल.

Fatigue, *s.* आयासः, क्लमः, श्रमः, अवसादः, खेदः, परिश्रमः, क्लेशः, ग्लानि-क्लांति-श्रांति-*f.*, तंद्रा; 'inured to f.' श्रमसहिष्णु, जितश्रम. —*v. t.* खिद् c., आयस् c., अवसद् c., क्लम् c. or श्रम् c. (क्ल-श्र-मयति), क्लिश् 9 P, ग्लै c. (ग्ल-ग्ला-पयति). **-ed**, *a.* श्रांत, क्लांत, खिन्न, ग्लान, अवसन्न, श्रमार्त, सश्रम, जातखेद-श्रम; 'to be f.' श्रम् 4 P, क्लम् 1, 4 P, आयस् 1, 4 P, खिद् pass.

Fatuous, *See* **Foolish**.

Fault, *s.* दोषः, छिद्रं, अगुणः, अपराधः, पापं, प्रमादः, स्खलितं, वाच्यं, वाच्यता; 'find f. with' दोषं ग्रह् 9 U, निंद् 1 P, उपा-लभ् 1 A, दुष् c. (दूषयति), (नात्र कुलपतिर्दोषं ग्रहीष्यति S. 3); 'chase, though found f. with' दृष्टदोषापि मृगया (S. 2); 'f. finder' दोषदृश्, दोषैकदृश्, छिद्रान्वेषिन्, दोषग्राहिन्, निंदक, पुरोभागिन्. **-y**, *a.* सदोष, सापराध, दोषवत्, दोषिन्, निंद्य, वाच्य, अवद्य, निंदार्ह. **2** अशुद्ध, असत्य, अयथार्थ, वितथ, अनृत, मिथ्या-अप-pr.; 'f. conclusion' पक्षाभासः, अपसिद्धांतः. **-less**, *a.* अ-निर्-दोष, अनवद्य, निरपराध, दोषहीन, अपाप, अनघ, अकल्मष, निष्कलंक, विशुद्ध, निर्मल, पवित्र. **2** सत्य, यथार्थ, अवितथ.

Faun, *s.* वनदेवता.

Fauna, *s.* प्राणिजातं.

Favour, *v. t.* अनुग्रह् 9 P, उपकृ 8 U, प्रसादं-उपकारं-कृ 8 U, or दृश् c., साहाय्यं दा 3 P, अभ्युपपद् 4 A; often by (*s.*); 'not inclined to f.' प्रसादपराङ्मुख; 'I wish to be f. ed with the mention of it' कथनेनानुग्राह्यमात्मानमिच्छामि (Ka. 134). **2** अनु-पा c. (पालयति), अनु-मन् 4 A, अनु-मुद् 1 A, अनुकूलयति (D.). **3** आश्रि 1 U, आ-अव-लंब् 1 A, स्वीकृ, अंगीकृ. —*s.* अनुग्रहः, प्रसादः, आनुकूल्यं, कृपा, प्रीति *f.*, स्नेहः; 'he is in the king's f.' स नृपप्रसादपात्रं-भाजनं. **2** आ-सं-श्रयः; साहाय्यं, उपालनं, अभ्युपपत्ति *f.*, आधारः. **3** हितं, उपकृतं-कारः, प्रियं, सुकृतं. **4** अनुज्ञा, अनुमति *f.*; 'in f. of' पक्षे (with gen.) 'I am speaking in your f.' अहं त्वदनुकूलं ब्रवीमि, त्वत्पक्षं समर्थये; 'ask a f.' प्र-सद् c., उपकारं प्रार्थ् 10 A; 'seek the f. of' आराध् c., अनुरंज् c. **-able**, *a.* अनुकूल, प्रसन्न, हितकारिन्, हितकाम, अनुग्रहपर, हित, हितबुद्धि, उपकारक; 'f. to' आवह, उत्पादक in comp. **-ably**, *adv.* सानुग्रहं, सानुकूल्यं, प्रसन्नतया. **-ite**, *s.* प्रियः, प्रीति-स्नेह-पात्रं-भाजनं, वल्लभः. —*a.* प्रिय, दयित, अभीष्ट, इष्ट, दयिततम, हृद्य, वल्लभ. **-itism**, *s.* पक्षपातिता, पक्षानुग्रहः.

Fawn, *s.* मृगशावः-बकः, मृगपोतः-शिशुः, हरिणवत्सः, कुरंगकः. —*v. i.* (upon) चाटुवचनैः आराध् c. or तुष् c., साष्टांगपातं सांत्व् 10 or उप-लल् 10, उपच्छंद् 10, छंदं अनुवृत् 1 A or अनुरुध् 4 A. **-er**, *s.* चाटुकारः, मांसवादः. **-ing**, *s.* उपलालनं, चाटूक्तिभिः आराधनं, उपच्छंदनं, चाटुवचनं. **-ingly**, *adv.* चाटुकरया, स्तुतिपूर्वं.

Fay, *See* **Fairy**.

Fealty, *s.* अनुरागः, भक्ति *f.*, निष्ठा, प्रभुभक्तिः.

Fear, *v.* भी 3 P, उद्विज् 6 A, संवि-त्रस् 4 P, (with abl.). **2** वि-, -, शंक् 1 A, तर्क् 10. **3** भयार्त *a.* भू, त्रस्, भी; ' do not f.' मा भैषीः. **-s.** भयं, भीः. भीति *f.*, सं-,त्रासः, साध्वसं, आशंका, दरः-रं; ' put in f.' *See* **Frighten;** through f.' भयात्, भीत्या. **-ful,** *a.* भयंकर, भयावह, भयप्रद, भीषण, भयानक, दारुण, भीम, रौद्र (द्री *f.*), उग्र, भैरव (वी *f.*), घोर, भीष्म, प्रतिभय **2** (Afraid) भीत, सभय, ससाध्वस, भयार्त, भीरु, शंकिन्, साशंक, त्रस्त. **-fully,** *adv.* सभयं, सत्रासं, भयेन. **2** दारुणं, घोरं, उग्रं. **-less,** *a.* अभय, निर्भय, अभीत, निःशंक, निर्भीक, निर्विशंक, अभीरु, अकुतोभय ; साहसिक (की *f.*), प्रगल्भ, साहसिन्. **-lessly,** *adv.* निर्भयं, निःशंकं, साहसेन.

Feasible, *a.* साध्य, शक्य, करणीय, संभाव्य, सुकर, उपपाद्य.

Feast, *s.* उत्सवः (lit. & fig.), महः, पर्वन् *n.*, उद्धर्षः; ' f. to the eyes ' नयनोत्सवः. **2** संभोजनं, विशिष्टान्नसंभारः, सहभोजनं. *-v. i.* प्रकामं भक्ष् 10: ' f. ing on grass ' तृणं प्रकामं भक्षयन्. **2** उत्तमान्नेन तृप् 4 P or संतुष् 4 P. *-v. t.* भोजनविशेषैः संतृप् *c.* or संतुष् *c.* **2** (fig.) आनंद् *c.*, प्रमुद् *c.*; नयनाभ्यां पा 1 P.

Feat, *s.* अवदातं or अद्भुतं कर्मन् *n*, आश्चर्यकर्मन् *n.*, चेष्टितं, कर्मन् *n.*, क्रिया.

Feather, *s.* पिच्छं, पक्षः, गरुत् *m.*, पत्रं, वाजः, पर्णं; ' peacock's f. ' बर्हः-र्हं; ' f. of arrows ' पुंखः, पत्रं, वाजः. ' f. bed ' मृदुशय्या, कोमलशयनं; 'he thinks it a f. in his cap ' स तद्गात्मनो विशिष्टगौरवपदं मन्यते. **-ed,** *a.* पक्षयुक्त, सपक्ष, पक्षिन्, गरुत्मत्, पत्रिन्, पतत्रिन्. **-y,** *a.* पक्षतुल्य-समान.

Feature, *s.* रूपं, आकृति *f.*, आकारः, लक्षणं; ' inauspicious f. s ' अभद्रलक्षणानि, अमंगलाकारः. **2** वदनाकृतिः; मुखरेखा, वदनाकारः. 3 (Sign) चिह्नं, लक्षणं, लिंगं.

Febrifacient, *a.* ज्वरोत्पादक.

Febrifuge, *a.* ज्वरघ्न (घ्नी *f.*), ज्वरनाशक-निवारक. *-s.* ज्वरापहं औषधं.

Febrile, *a.* सज्वर, ज्वरित, ज्वरार्त.

February, *s.* माघः, फाल्गुनः, तपस्यः.

Feces, *s.* मलं, पुरीषं, विष् *f.*, उच्चारः, अव(व)-स्करः, विष्ठा; *See* **Dung.** **2** खलं, उच्छिष्टं, शेषं. **-Fecal,** *a.* विण्मय-मलमय (यी *f.*), अशुद्ध, अमेध्य. **-Feculent,** *a.* समल, कलुष, अमेध्य, मलदूषित, खलिन्.

Fecund, *a.* बहुप्रज, बहुपत्य. **2** अवंध्य, बहुफलप्रद, उर्वर (as soil). **-Fecundate,** *v. t.* सफलीकृ 8 U; रेतः सिच् 6 P. **-Fecundity,** *s.* सफलता, अवंध्यत्वं, प्रसवनं, फलवत्त्वं, स्फीति *f.*

Federal, Federate, *a.* संहत, संघातवत्, सामयिक-सांगतिक (की *f.*), द्वैतसंधि, संयुक्त, संधिसंश्लिष्ट.

Fee, *s.* शुल्कः-ल्कं, वेतनं, प्रतिफलं, उपार्जनं, निस्तारः, पारितोषिकं; ' monthly f. ' मासिकं; ' f. simple ' स्वाधीना-स्वतंत्रा-भूमिः.

Feeble, *a.* दुर्बल, अशक्त, शक्तिहीन, निर्बल, क्षीणशक्ति, अल्पशक्ति, अल्पबल वीर्य-सत्त्व, क्षीण, अवसन्न, क्षाम, असमर्थ, शिथिलबल निःसत्त्व. **-ness,** *s.* दौर्बल्यं, क्षीणता, अल्पबलं, अल्पवीर्यं, तेजोहानि *f.*, वीर्यहानिः, असामर्थ्यं, अवसादः, अशक्ति *f.*, शक्तिक्षयः, सत्त्वनाशः, निःसत्त्वता. **-Feebly,** *adv.* दुर्बलतया, अल्पशक्त्या, मंदं.

Feed, *v. t.* भुज् *c.*, अश् *c.*, अन्नदानेन आप्यै *c.* or परि-पुष् *c.* **2** पुष् 1,9 P or *c.*; सं-भृ 3 U, पा *c.* (पालयति), अन्नेन संवृध् *c.*, or संतृप् *c*, or संतुष् *c.* **3** चर् *c.* **4** उपकॢप् *c.*, उपस्था *c.* (स्थापयति). *-v. i.* (on) भक्ष् 10, अद् 2 P; *See* **Eat;** oft. by अशन, भुज् in comp ; पिशिताशनः, हुतभुक् &c. **2** (Grass) चर् 1 P. *-s.* भक्ष्यं, भोज्यं. **-er,** *s.* भोजयितृ *m.*, अन्नदातृ *m.* आशयितृ *m.* **2** पोषकः, उपकल्पकः. **3** भक्षकः, भोजिन् *m.*. अत्तृ *m.* भोक्तृ *m.*, आशिन् *m.*; अद्-भुज्-आशिन्-अशन in comp. **-ing,** *s.* अन्नदानं, पालनं, पोषणं, भरणं. **2** भक्षणं, खादनं, भोजनं, अशनं.

Feel, *v. t.* अनुभू 1 P, वि-भू *c.*, (पादचारमपि न व्यभावयत् R. xi. 10), ज्ञा 9 U, उपलभ् 1 A, विद् 2 P, 10 A; ' ' f. certain ' इदं ज्ञा, प्रति-इ 1 P; ' I felt his remarks much ' तस्य वचो मम हृदयमर्माणि अस्पृशत्-अभिनत्. **2** (Think) मन् 4 A, गण् 10, आकल् 10; *See* **Consider;** ' are felt by the mind as pleasant ' मधुरतराण्यापतंति मनसः (K a. 103). **3** स्पृश् 6 P, परामृश् 6 P, आलभ् 1 A, स्पर्शेन परीक्ष् 1 A or विमृश् 10; ' f. ing the pulse ' नाडीं स्पृष्ट्वा. *-v. i.* (आत्मानं) गण्, मन्. **2** (for) अनुकंप् 1 A, समदुःख *a.* भू; ' I f. sorry for you ' अहं तव कृते दुःखाकुलोऽस्मि; ' felt proud of his company ' तत्समागमेनारूढगौरवमिवात्मानं मेने; ' I f. easy now ' लब्धं मयेदानीं स्वास्थ्यं (S. 4); ' I f. better ' अस्ति मे विश्रमः (S. 3). **-er,** *s.* स्पर्शशृंगः ' it was intended as a f. ' साधारणलोकमतज्ञानाय इदं प्रयुक्तमासीत्. **-ing,** *s.* अनुभवः, अनुभूति *f.*, संवेदनं, बोधः, ज्ञानं, उपलंभः, उपलब्धि *f.*, उपागमः, चैतन्यं, चेतना; संज्ञा. **2** स्पर्शः, परामर्शः, संपर्कः, स्पर्शजं ज्ञानं. **3** वृत्ति *f.*, रसः, भावः, रागः, विकारः, चित्त-मनो-वृत्तिः, मनोविकारः-धर्मः; ' f. of anger ' कोपवृत्तिः. **4** कृपा, दया, अनुकंपा, करुणा, समदुःखिता; 'a man of f.' सहृदयः, सचेतस् *m.* ' what man of f.

in not affected at heart' सचेतसः कस्य मनो न दूयते (K. v. 48). -a. चेतन, चेतनायुक्त, चैतन्य-बोध-विशिष्ट. 2 रसवत्, रागिन् भाविक, सरस. -ingly, *adv.* सरसं, सरागं, ज्ञानपूर्वं, स्वानुभूतिपूर्वं. 2 सदयं, सानुकंपं.

Feign, *v. t.* मनसा कल्प् c. or सृज् 6 P. 2 कपट-व्याज-छद्म कृ 8 U; अप-दिश् 6 P; 'f. ing illness' शरीरास्वास्थ्यमपदिश्य; oft. ex. by कृतक, कृत्रिम, or कपट-व्याज-छद्म-मिथ्या in comp.; 'he f. ed himself to be dead' आत्मानं मृतवत्संदर्शयामास; 'f. ing anger' कृतकं कोपं कृत्वा; 'f. ing sleep' प्रसुप्तलक्षण, व्याजसुप्त, छद्मसुप्त. -ed, *a.* व्याज-कपट-छद्म-मिथ्या in comp.: कूटार्थ, कल्पित, कृतक, कृत्रिम; 'f. quarrel' कृतककलहः, 'a f. dress' कपटवेशः; 'f. sleep' व्याजनिद्रा; 'a f. ascetic' छद्मतापसः. -edly, -ingly, *adv.* मिथ्या, सकपटं, सव्याजं, छद्मना. -er, *s.* कापटिकः, छद्मिन् *m.*, प्रतारकः; 'f. of illness' आतुरलिंगिन्.

Feint, *See* **Pretext.**

Felicity, *s.* सुखं, श्रेयस् *n.*, परमसुखं, परमानंदः, धन्यता, सौभाग्यं, कल्याणं, प्रहर्षः; 'f. of expression' वचसां प्रौढत्वं (Mal. 1). 2 (Eternal f.) अपवर्गः, मोक्षः, निःश्रेयसं, परमा गतिः, परमपदं, मुक्ति *f.*, कैवल्यं, निर्वाणं, श्रेयस्, अमृतं. 3 सहजता, अकृत्रिमता, अनाहार्यत्वं. -ous, *a.* श्रेयस्कर (री *f.*), अतिकल्याण, परमसुखिन्, धन्य, सुभग. -Felicitate, *v. t.* अभिनंद् 1 P or c., दिष्ट्या वृध् c.; *See* **Congratulate.** -ion, *s.* अभिनंदनं, धन्यवादः, कल्याणवचनं.

Feline, *a.* मार्जारीय, बैडाल (ली *f.*).

Fell, *s.* चर्मन् *n.*, अजिनं, दृति *f.*, कृत्ति *f.* 2 औपलाद्रि *m.* -a. निष्ठुर, क्रूर, दारुण, उग्र. -v. t. नि-अव-पत् c., अवकृत् 6 P. अवच्छिद् 7 P, नि-अव-भंज् 7 P. भूतले पत् c., सद् c. (भ्रातयति). -er, *s.* निपातकः, छेत्तृ *m.*

Fellow, *s.* सहायः, मित्रं, सहचरः, अनुगामिन् *m.*, सजुस् *m.*, सहवर्तिन् *m.*, वयस्यः. 2 समपदभाज् *m.*, तुल्यपदस्थः, सवयस्कः. 3 जनः, पुरुषः; 'this f. is bold' धृष्टोऽसौ जनः. 4 सजातीयः, सजातिः. 5 यमः, यमकः, एकतरः, युग्मकः. 6 कापुरुषः, माणवकः, अल्पः; 'my good f.' भद्र, सौम्य. In comp. words ex. by सम-सह; 'f.-being, -creature' समानजातिः-जातीयः, सजातीयः, समभूतं; 'f.-citizen' एकनगरस्थः, एकग्रामीणः; 'f.-citizenship' पौरसख्यं, पौरसाहित्यं; 'f. countryman' स्वदेशजः, स्व-एक-देशीयः; 'f.-feeling' सहानुभूति *f.*, समदुःखत्वं, समभावः, भूतानुकंपा; 'f.-student, scholar' सहाध्यायः, सतीर्थः, सहाध्यायिन् *m.*, सहपाठकः; 'f.-labourer, -worker' सहकारिन् *m.*, संभूयकारिन् *m.*, सहकर्मिन् *m.* 'f.-servant' सहभृत्यः, एकभृत्यः; 'f.-soldier' सहयोद्धा; 'f. sufferer' सम-सह-दुःख-खिन्न, समदुःखभाज्, सहभोगिन् 'f. traveller' सहयायिन्, सहगामिन्; 'f. of a body' पारिषद्यः, पांक्तेयः, श्रेण्यभ्यंतरः. -ship, *s.* साहाय्यं, साहित्यं, संसर्गः, संगः-गमः, संघातः, संयोगः, साहचर्यं, सख्यं, मैत्री, समागमः. 2 वृत्ति *f.* 3 पारिषद्यपदं.

Felly, *See* **Circumference.**

Felon, *s.* साहसिकः, घोरपातकः, आततायिन् *m.*, महापापिन्-पातकिन् *m.*, महापराधिन् *m.* -ous, *a.* आततायिन्, जिघांसु, वधोद्यत. 2 दुराचार, दुष्ट, पापिष्ठ, दुर्वृत्त, अतिनिंद्य. -y, *s.* महापापं-पातकं, महापराधः, साहसं आततायिता, घोरपापं.

Felt, *s.* ऊर्णा, औणकं, ऊर्णायुः, कंबलः.

Female, *s.* स्त्री, नारी; *See* **Woman.** -a. Ex. by the suffixes आ, ई, or वधू in comp.; 'f. sparrow' चटका; हरिणी, सिंही, चक्रवाकवधूः, &c.; 'f. friend' वयस्या, सखी, सहचरी, आलि *f.* 'f. apartments' अवरोधगृहं, शुद्धांतः, अंतःपुरं; 'a f. form' स्त्रीरूपं, स्त्रीसंस्थानं; 'a f. dress' स्त्रीनेपथ्यं-वेषः.

Femesole, *s.* अनूढा स्त्री.

Feminine, *a.* स्त्रैण (णी *f.*), स्त्रीजातीय, स्त्रीधर्मन्. 2 कोमल, मृदु, पेलव, सुकुमार. 3 (In gram.) स्त्री; 'this word is masculine or f.' अयं शब्दः पुंसि स्त्रियां च.

Fen, *s.* अनूपः, अनूपभूः, कच्छभूः, पंकः, कर्दमः. -Fenny, *a.* जलाढ्य, सजल, पंकिल.

Fence, *s.* वृति *f.*, आवरणं, प्राकारः, प्राचीरं, वेष्टनं, वरणः, शा(सा)लः. 2 रक्षा-शर्म, गुप्ति *f.* -v. t. वृत्या रक्ष् 1 P or आ-परि-वृ 5 U or c. or परिवेष्ट् c. or अव-नि-रुध् 7 U. -v. i. द्वंद्वयुद्धे अभ्यस् 4 U or शिक्ष् 1 A. 2 यष्टियुद्धं कृ 8 U, दंडादंडि युध् 4 A. -er, *s.* असि-खड्ग-योधः, दंडयोद्धृ *m.* -ing, *s.* यष्टिदंडयुद्धं, आयुध-शस्त्र-विद्या. -less, *a.* अरक्षित, अनावृत.

Fend, *v. t.* वृ c. निवृ 10, प्रतिहन् 2 P.

Fender, *s.* अंगारगुप्ति *f.* 2 कवचः, रथगुप्तिः.

Fennel, *s.* श्र-सा-लेयः, छत्रा, मधुरिका.

Feracious, *See* **Fecund.**

Ferine, *See* **Beastly.**

Ferment,-ation, *s.* मंडः-ड, अभिषवः, फेनकः, किण्वः-ण्वं, सुरामंडः, कारोत्तरः, नग्नहुः (*m.*). 2 अंतः-क्षोभः-तापः-दाहः-उत्सेकः-वेगः, उत्तापः. -v. t. आकुलीकृ 8 U, अंतः क्षुभ् c., उत्सिच् 6 P or c., उत्तप् c., अंतर्वेगं उत्पद् c., अंतः-तप् c. -v. i. फेनायते (D.), उत्सिच् pass., अंतः क्षुभ् 4 P or तप् 4 A, अंतस्तापं वा 2 P. 2 क्षुभ्, उत्तप्.

Fern, *s.* बहुपत्रकः.

Ferocious, *a.* रौद्र (द्री *f.*), उग्र, क्रूर, अतिक्रूर, दारुण, क्रूरकर्मन्, भयानक, साहसिक (की *f.*); *See* **Grim, Dreadful,** also. **-ness, -Ferocity,** *s.* रौद्रता, क्रौर्यं, उग्रता, &c.

Ferreous, *a.* लौह (ही *f.*), आयस (सी *f.*). लोहमय (यी *f.*), अयोघर्मन्.

Ferret, *s.* बभ्रुः, नकुलः.

Ferruginous, *a.* लोहमलयुक्त.

Ferrule, *s.* लोहवलयः-यं, लौहरक्षणी.

Ferry, *s.* तरः, तरणस्थानं, घट्टः; 'f. boat' तरणीः, त(ता)रण्यः-र्णी *f.*, तरीः, तरण्डुः, उडुपः, वहित्रं; 'f.-man' तरनायकः, नाविकः, तारकः, तारयः. **-v.** *t.* (over) नावा तॄ 1 P. or पारं वह् 1 P.

Fertile, *a.* शस्यप्रद, उर्वर, बहुफलप्रद, बहुशस्यद, अवंध्य, स्फीत; 'f. in produce' बहुशस्य. **2** (Fig.) निर्माणकुशल, कल्पक, संविधायक. **-ity, -ness,** *s.* फलवत्ता, फलदत्ता, सफलता, अवंध्यत्वं, स्फीति *f.* **-ize,** *v. t.* सफल- फलप्रद-*a.* कृ 8 U, फलदी-कृ, आप्यै c., स्फीतीकृ.

Ferule, Ferula, *s.* वेत्रं, दंडकाष्ठं.

Fervent, *a.* चंड, उत्सुक, तीक्ष्ण, सातिशय, उग्र, सोत्साह, आसक्त, व्यग्र, उत्कट, उत्तप्त, उत्सुक, सोद्वेग; 'f. in piety' भक्तिव्यग्र, अतिभक्त. **-ly,** *adv.* सोत्साहं, सरभसं, सोत्सुकं, व्यग्रतया, औत्सुक्येन, उत्कटतया. **-Fervency,** *s.* व्यग्रता, उत्साहः, औत्सुक्यं, उत्कटता, तीक्ष्णता, चंडता, आसक्ति *f.*, मनोनिर्बंधः.

Fervid, *a.* प्रचंड, तीव्र, तीक्ष्ण, उत्तप्त, सातिशय, प्रखर, स्निग्ध, उग्र. **-Fervour,** *s.* प्र-चंडता, तीव्रता, तीक्ष्णता, उत्तापः, उत्कटता, व्यग्रता; 'religious f.' अतिभक्ति *f.*, भक्तिव्यग्रता, श्रद्धोन्मादः.

Festal, *a.* औत्सविक (की *f.*).

Fester, *v. i.* पूय् 1 A, पूतीभू 1 P, पक्व *a.* भू, सपूय *a.* भू.

Festival, *s.* उत्सवः, महः, पर्वन् *n.*, क्षणः, उद्धर्षः, उद्धवः, यात्रा, अभ्युदयः; 'public or general f.' यात्रोत्सवः.

Festive, *a.* आनंदप्रद, सोत्सव, हर्षण, सानंद, उत्सव in comp.; 'f. day' उत्सवदिनं. **-ity,** *s.* उत्सवः, समुत्सवः, उत्सवकालः. **2** प्रमोदः, दर्पः, आनंदः, आल्हादः.

Festoon, *s.* माला, हारः, स[illegible] *f.*

Fetch, *v. t.* आहृ 1 P, उपा-आ-नी 1 P, उपा-दा 3 A, **2** निष्कृष् 1 P, उत्पद् c., क्षृ c.; 'f. a deep sigh' दीर्घं निश्वस् 2 P, what price does the book f. कियता मूल्येन तत्पुस्तकं विक्रीयते ? 'f. up' उद्धृ 1 P, 10, आ-सद् c., *See* Overtake. **-s.** कपटं, व्याजः, अपदेशः, छलं.

Fete, *v. t.* तृप् c., तुष् c. **-s.** उत्सवः.

Fetid, *a.* पूतिगंधि, पूत, अशुगंधि, उग्रगंध, दुर्गंध.

Fetor, *s.* दुर्गंधः, पूति-उग्र-गंधः.

Fetter, *s.* निगडः-डं, बंधनं, पाशः, शृंखला-लं. **-v.** *t.* निगडेन बंध् 9 P, संयम् 1 P, यंत्र् 10, निगडयति (*D.*). **-ed,** *a.* निगडित, पाशबद्ध, संयत, शृंखलित, संदानित.

Fetus, *s.* गर्भः, भ्रूणः, पिंडः, कललं-लं, गर्भस्थः शिशुः.

Feud, *s.* कलहः, कलिः, विग्रहः विरोधः, विपक्षता, द्वंद्वं, युद्धं; 'family f.' गृहच्छिद्रं, गृहरंध्रं, अंतर्भेदः.

Feudatory, *s.* सामंतः.

Fever, *s.* ज्वरः (lit. & fig.), तापः, देहदाहः-तापः; 'inflammatory f.' दाहज्वरः; 'typhoid f.' संनिपातज्वरः, तंद्रिकसंनिपातः; 'ardent f.' तापरेत्स्वणः; 'relapsing f.' मुक्तानुबंधिन् *m.*, संततः. **-v.** *t.* उद्-सं-तप् c., ज्वर् c. (ज्वरयति). **-ish,** *a.* ज्वरार्त, ज्वरग्रस्त, ज्वरातुर, ज्वरपीडित, ज्वरित, सज्वर, ज्वरिन्. **2** ज्वरोत्पादक, ज्वरजनक.

Few, *a.* अल्प, कतिपय, स्तोक, परिमित, मित, अप्रचुर, अबहु; 'a f.' कतिचित्, स्तोकाः, कतिपयाः. **-ness,** *s.* अल्पत्वं, स्तोकत्वं.

Fiance, *s.* वधू.

Fiasco, *s.* भंगः, अनिष्पत्ति *f.*, असिद्धि *f.*

Fiat, *s.* आज्ञा, निर्देशः, शासनं, नियोगः, व्यवस्थापत्रं.

Fib, *See* **Falsehood.**

Fibre, *s.* तंतुः, सूत्रं, गुणः, तंत्रं. **2** केस(श)रः-रं, अंशुः, पक्ष्मन् *n.* **3** शिरा, नाडी, स्नसा; 'f. of a lotus' मृणालः-लं-ली, बिसं. **-ed, -ous,** *a.* तंतुमत्, सूत्रिन्, केसरिन्, तंतुमय (यी *f.*), शिराल.

Fickle, *a.* चपल, चंचल, लोल, तरल, चल, अस्थिर, अनवस्थित, अधीर; (of persons only) चलचित्त, चंचलहृदय, लोलबुद्धि, नैकभावाश्रय, प्रकृतितरल, लोल-चंचल-मति, अस्थिरबुद्धि. **-ness,** *s.* चापल्यं, तरलता, लोलता, चांचल्यं, अधीरता, अस्थिरता, चलचित्तता, मनोलौल्यं.

Fiction, *s.* कल्पना, रचना, सृष्टि *f.*; मनःकल्पना-सृष्टिः, मानसी सृष्टिः. **2** मिथ्याकथा, कल्पिता कथा. **-Fictitious,** *a.* कृतक, कृत्रिम, कल्पित, असत्य, मृषार्थक, कृत्रार्थ, कपट, मिथ्या-कूट in comp. **-ly,** *adv.* मिथ्या, सकपटं, मृषा सकृटं, सव्याजं.

Fiddle, *s.* शा(सा)रंगी, पिनाकी. **-v.** *i.* सारंगीं वद् c., 'f. stick' शारिका, कोणः, घर्षिका.

Fidelity, *s.* भक्ति *f.*, आसक्तता, अनुरागः, निष्कपटत्वं, विश्वास्यत्वं, स्वामि प्रभु-निष्ठा-भक्ति, अभेद्यता; 'f. to a husband' पातिव्रत्यं पतिसेवा मर्यादा-आर्जवं

Fidget, *v. i.* चपल-चंचल-*a.* भू 1 P. **-s.** चापल्यं, चंचलता. **-y,** *a.* चपल, चंचल, लोल, अशांत, अधीर; *See* **Fickle.**

Fiducial, *a.* विश्वासिन, विश्वस्त, असंदिग्ध.

Fiduciary, *a.* न्यस्त, निक्षिप्त. **-s.** न्यास-निक्षेप-धारिन्.

Fie, *interj.* धिक् (with acc.),sometimes with gen.

Fief, *s.* क्षेत्रं, भूमि *f.*, क्षेत्रभूमिः.

Field, *s.* क्षेत्रं, भूमि *f.*, वप्र:-प्रं; 'a collection of f. s' कैदारकं, कैदार्यं. क्षेत्रं, कैदारिकं; 'f. of battle' रणभूमिः, रणाजिरं, रणांगनं-णं, रणं, समरभूमिः; 'f. marshal' सेनापतिः, बलाध्यक्षः, चमूपतिः, दंडनायकः, सेनानी *m.* 'f. sport-' वनक्रीडा, अरण्य-मृगया-विह रः; the general took the f.' सेनानीर्युद्धाय प्रवृत्तः; 'they lost the f.' तस्मिन्युद्धे पराजिग्यिरे. **2** अवसरः, प्रसरः, स्थानं, विषयः.

Fiend, *s.* पिशाचः, राक्षसः, भूतः, वेतालः; *See* **Demon** also. **-ish -like,** *a.* पिशाचतुल्य अतिदारुण, पैशाच (ची *f.*), राक्षस (सी *f.*), आसुर (री *f.*), अतिक्रूर.

Fierce, *a.* उग्र, क्रूर, घोर, रौद्र (द्री *f.*), दारुण, भीषण, भैरव (वी *f.*); *See* **Dreadful, Grim,** also. **2** तीक्ष्ण, त व्र, चंड, प्रखर, परुष, निष्ठुर (of voice &c.). **3** संरब्ध, कोपज्वलित, क्रोधेद्ध, कोपाकुल, समन्यु, कोपाद्दीपित, क्रोधव्यंजक. **-ly,** *adv.* तीक्ष्णं, तीव्रं, उग्रं, क्रूरं, घोरं, चंडं, निष्ठुरं, सक्रोधं, संरंभेण. **-ness,** *s.* क्रूरता, उग्रत्वं, रौद्रता. **2** तीक्ष्णता, चंडता. **3** संरंभः, अतिमन्युः, कोपोन्मादः, क्रोधातिशयः.

Fiery, *See* under **Fire.**

Fife, *s.* वेणुः, वंशः. **-er,** *s.* वांशिकः, वेणुवादकः.

Fifteen, *a.* पंचदशन्; 'f.-th' पंचदश (शी *f.*).

Fifty, *a.* पंचाशत्; 'f.-th' पंचाश.(शी *f.*), पंचाशत्तम (मी *f.*).

Fig, *s.* (Tree) अंजीरः, न्यग्रोधः, उदुंबरः; (fruit) न्यग्रोधं, उदुंबरं, or ex. by फलं in comp.; 'I care a f. for you' न त्वां तृणायापि मन्ये-गणयामि.

Fight, *v. i* युध् 4 A, विग्रह् 9 P, संप्र-हृ 1 P. संग्रामं आरभ् 1 A. वैरायते (D.), प्रति-आ-युध् (with acc.); 'f. a cause' कार्यार्थे युध **-s**, **-ing,** *s.* युद्धं, रण:-णं, आयोधनं, समर:-रं विग्रहः; *See* **Battle.** **-er,** *s.* योद्धृ *m.*, युयुत्सुः.

Figment, *s.* कल्पना, मिथ्या-कल्पित-कथा, मानसी सृष्टिः

Figurante, नर्तकी, लासिका.

Figure, *s.* आकारः, रूपं, आकृति *f.*, मूर्ति *f.* **2** काय , देहः, विग्रहः, अंगं, गात्रं, वपुस् *n.* (**Body** q. v.). **3** मूर्तिः, प्रतिमा, प्रतिरूपं-कृति *f.* **4** अंकः. **5** अलंकारः; 'f. of speech' वाक्यालंकारः. **6** रूपकं, आरोपः, लक्षणा, उपलक्षणं-णा, उपचारः **7** प्रतिष्ठा, गौरवं, यशस् *n.*, वर्णः, कीर्ति *f.*; *See* **Fame.** **-v. t.** वि-धा 3 U, विरच् 10, निर्मा 3 A, सं-परि-क्लृप् c. **2** वर्ण् 10, चित्र् 10, लिख् 6 P. वि-आ°, रूप् 10, चित्रीकृ 8 U, कर्बुरीकृ **3** (To oneself) वि-भू c., चिंत् 10, क्लृप् c., विगण् 10. **-Figurate,** *a.* साकार, रूपवत्, मूर्तिमत्, सरूप. **-Figurative,** *a.* सालंकार. **2** लाक्षणिक-औपचारिक (की *f.*), उपलक्षित; 'f. use' उपचारः. **-ly,** *adv.* सालंकारं, सोपलक्षणं; 'to be used f.' उपचर् pass. (with loc.); अचेतनेपि कूले चेतनवदुपचारदर्शनात्, तस्माचेतनवदुपचर्यते (S. B. 99, 100).

Filament, *s.* केश(स)र:-रं, तंतुः. (त्रं, पक्ष्मन् *n.*, अंशुः; 'f. of a lotus' मृणालः-लं, बिसं, किंजल्कः.

Filch, *v. t.* मुष् 9 P,चुर् 10, अप-हृ 1 P. **-ing,** *s.* स्तेयं, अपहारः, चौर्यं, मोषणं.

File, *s.* पंक्ति *f.*, आवलि-ली *f.*, श्रेणि-णी *f.*; 'f. of an army' दंडव्यूहः, सैन्यश्रेणिः. बलविन्यासः. **2** सूत्रं, गुणः, तंतुः **3** लेख्यश्रेणी, लेख्यपत्रसम् ... **4** व्रश्चनः, पत्रपरशुः. **-v. t.** यथाक्रमं रच् 10 or श्रेण्यां आरुह् c. **2** घृष् 1 P, मृज् 2 P. **-v. i.** व्यूहेन प्र-या 2 P.

Filial, *a.* पुत्रानुरूप, पुत्रयोग्य, पुत्रीय; gen. पुत्र in comp.; 'f. duty' पुत्रधर्मः; 'f. affection' पितृवात्सल्यं, पितृभक्ति *f.* **-ly,** *adv.* पुत्रवत्, पुत्रधर्मानुरूपं **-Filiation,** *s.* पुत्रत्वं, पुत्रीकरणं.

Filiform, *a.* सूत्राकृति.

Filings, *s.* लोहचूर्ण-किटं, लोहजं.

Fill, *v.t.* पृ-पृ 3 U, भृ 3 U, आ-नि-सं-चि 5 U. प्र-आ-सं-पूर् 10, आ-सं-कॄ 6 P, व्याप् 5 P, व्यश् 5 A, आवृ 5 U; better ex. by 'f. ed'; 'it f. ed-my heart with terror' तेन मम हृदयं भयसंकुलं बभूव. **2** प्रचुरीकृ 8 U, बहुलीकृ, संकुलीकृ. **-s.** Ex. by यथेच्छं, पर्याप्तं, आतृप्ति, प्र-नि-कामं; 'drank his f.' यथेच्छमापिबत्; नीवारौदनमंडं पर्याप्तमाचामति (U. 4) 'drinks his f. &c.' **-ed,** *a.* पूरित, पूर्ण, सं-परि-पूर्ण, आ-सं-कीर्ण, संकुल. आ-सम-कुल, व्याप्त, नि-सं-चित, आवृत, संभृत, आविष्ट, गर्भ in comp.

Fillet, *s.* पट्टः, बंधनं, वेष्टनं, बंधः (केशानां).

Fillip, *s.* अंगुलिप्रहार-घातः-ताडनं, छोटिका.

Filly, *s.* किशोरी, बालतुरगी-वाजिनी-घोटिका

Film, *s.* पटलं, सूक्ष्मतंतुः, सूक्ष्मत्वच् *f.* पुट:-टं; 'f. of the eye' अक्षिपटलं, अंतर्धानं **-y.** *a.* पटलावृत, सपटल.

Filter, *v. t.* स्रुध् c., संस्रुज् 2 P, पू 9 U. —*v. i.* विर्गल् 1 P, निस्यंद् 1 A, निःसृत्य स्रुध् 4 P.

Filth, *s.* मलः-लं, कालुष्यं, मालिन्यं, अव-(व)स्करः, कल्कं, खलं, पंकः, कर्दमः. **—y,** *a.* मलिन, कलुष, समल, मलीमस, मलदूषित, पंकिल, पंकिन. 2 अशुद्ध, अमेध्य, अपवित्र. 3 कुत्सित, निंद्य, गर्ह्य, दूषणीय, कु-कद् pr.

Fin, *s.* पक्षः, देहधिः, वाजः (मत्स्यानां); 'f.-footed' जालपादः-द्. **—less,** *a.* पक्षहीन-रहित. **—Finny,** *a.* सपक्ष, पक्षविशिष्ट.

Final, *a.* अंतिम, अंत्य, अंत-शेष in comp., पश्चिम, चरम. 2 निःसंदेह, परिच्छिन्न, सुनिश्चित, अविकल्प, सुनिर्णीत. 3 अपरिवर्तनीय, अप्रतिकार्य. **—ly,** *adv.* अंततः, अंते, शेषे. 2 निरुत्तरतया, सपरिच्छेदं.

Finance,-s, *s.* आयः, करः, बलिः, धनागमः, शुल्कं, राजस्वं; 'his financial condition is prosperous' परिस्फीतं तस्य कोशजातं. **—Financier,** *s.* कोशाध्यक्षः, धनाधिकारिन् *m.*

Find, *v. t.* आप् 5 P, लभ् 1 A, अधिगम् 1 P, विद् 6 U, आ-समा-सद् c., दृश् 1 P, ईक्ष्-या 2 P, [illegible] प्रतिपद् 4 A. 2 (F. out) बुध् 1 P, ज्ञा 9 U, अवगम् 1 P, अव-इ 2 P, वि-भू c.; निरूप् 10, अनुसंधा 3 U, उपलभ्, अन्विष् 4 P, निर्णी 1 P, निश्चि 5 U, अव-निर्-धृ 10; 'they found him guilty' सोपराधीति ते निर्णिन्युः, तैः सोपराधी स्थापितः. 3 उप-सं-क्लृप् 10, चिंत् 10. 4 ख्या-रूया 2 P, ख्या-कृ 8 U, ख्यकीकृ. **—ing,** *s.* अधिगमः, अवाप्ति *f.* 2 निर्णयः.

Fine, *a.* सूक्ष्म, तनु, श्लक्ष्ण, अस्थूल, विरल; 'f. cloth' सूक्ष्मवस्त्रं, अंशुकं, सुवासस् *n.* 2 तीक्ष्ण, तीव्र, कुशाग्रीय, मार्मिक. 3 पेलव, सुकुमार, कोमल, मृदु. 4 विशुद्ध, विमल, निर्मल. 5 परम, उत्तम, उत्कृष्ट, विशिष्ट. 6 सुंदर, कांत, शोभन, वाम, चारु, रूपवत्, सुभग, gen. by सु in comp.; 'of f. teeth' सुदती; 'having f. eyes' सु-वाम-लोचना; 'a f. day' सुदिनं; 'f. art' कला, 'f.-fingered' लघुहस्त; 'it is a f. proposal' उदारः-प्रथमः-कल्पः. 'in fine' अंततः, शेषे, एतावता, एवं च. *v. t.* शुध् c., पू 9 U, मलं हृ or अपकृष् 1 P. **—ly,** *adv.* सूक्ष्मं, विरलतया. 2 चारु, शुभ, सुंदरं, सु pr. **—ness,** *s.* सूक्ष्मता, विरलता, तीक्ष्णता, &c. 2 कांति *f.*, शोभा, चारुता, लावण्यं. **—ry,** *s.* शोभा, आडंबरः, बाह्यशोभा. 2 अलंकारः, मंडनं, भूषणं, प्रसाधनं, आभरणं, परिकर्मन् *n.*, परिष्कारः; 'fond of f.' प्रियमंडन, अलंकारप्रिय.

Fine, *s.* दंडः, अर्थ-धन-दंडः; 'liable to f.' दंड्य. **—v. t.** दंड् 10 (two acc.), दंडं कृ c. (दापयति) with instr. of giver.

Finesse, *s.* माया, सूक्ष्मोपायप्रयोगः, व्यवहारः. 2 कौशलं, धूर्तता.

Finger, *s.* अंगुलि-ली *f.*, करशाखा; 'fore-f.' तर्जनी, प्रदेशि(श)नी; 'middle f.' मध्यमा; 'third f.' अनामिका; 'last f.' कनिष्ठा, कनिष्ठिका, कनीनी-निका; 'f.-ring' अंगुलीयं, अंगुली(री)यकं, ऊर्मिका; 'three f. s in breadth' त्र्यंगुलं (दारु). **—v. t.** अंगुल्या स्पृश् or परामृश् 6 P.

Finical, *a.* अतिसूक्ष्म, एकांतकोमल-पेलव, अत्युत्कृष्ट.

Finis, *s.* *See* **End.**

Finish, *v. t.* समाप् c., सं-पू c.-पूर् 10, निर्वृत् c., अवसो 4 P, निर्-सं-पद् c., साध् 5 P or c.; अंतं गम् 1 P, निःशिष् c., निःशेषीकृ 8 U, पारं गम्. 2 संस्कृ 8 U, परिष्कृ, यत्नतः साध्. **—s.,** **—ing,** *s.* समाप्ति *f.*, अंतः, निर्वृत्ति *f.*, सिद्धि *f.*, अंतगमनं, &c.

Finite, *a.* प्रमेय, परिच्छेद्य, निरूपणीय, नियत, समर्याद, परिमित, सावंत; 'not f.' अनंत. **—ly,** *adv.* समर्यादं, नियतं.

Fir-tree, *s.* देवदारु *m.*, *n.*, शक्रपादपः, पारिभद्रकः, भद्रदारु, द्रुकिलिमं, पीतदारु, दारु, पूतिकाष्ठं.

Fire, *s.* अग्निः, वैश्वानरः, ज्वलनः, अनलः, पावकः, कृशानुः, वह्निः, दहनः, जातवेदस् *m.*, हुताशनः, शिखिन् *m.*, हुतभुज् *m.*, हुतवहः, बर्हिः, शुष्मन् *m.*, कृष्णवर्त्मन् *m.*, तनूनपात्, उषर्बुधः, शिखावत् *m.*, हव्यवाहनः, हिरण्यरेतस् *m.*, चित्रभानुः, विभावसुः, शुक्रः, शुचिः, कृपीटयोनिः. 2 तेजस् *n.*, सत्त्वं, उत्साहः; 'on f.' अग्नि-हुतवह-परीत, अग्निदीप्त; 'submarine f.' वाडवः, और्वः, वडवानलः; 'set on f.' दह् c., दीप् c., अग्निं विसृज् 6 P (with loc.) अग्निना ज्वल् c. or दह् c.; 'take f.'; *See* under **Catch.** **—v. t.** दह् 1 P, ज्वल् c., इंध् 7 A, अग्निसात्कृ 8 U. 2 उत्तिज् c., उद्दीप् c., प्रोत्सह् c., प्रचुद् 10, संक्षुभ् c., प्रेर् c., संधुक्ष् 10. **—v. i.** दीप् 4 A, ज्वल् 1 P, दह् pass. 2 लोहगोलान् प्रक्षिप् 6 P or विसृज् 6 P. 'F.-arms' आग्नेयास्त्राणि; 'f-brand' अग्निकाष्ठं, अंगारः-रं, अलातं, उल्का, उल्मुकं. 2 प्रोत्साहकः. 'f.-fly' पतंगः, शलभः, खद्योतः, ज्योतिरिंगणः, प्रभाकीटः; 'f.-pan' *See* **Hearth**; 'f.-place' चुल्लि-ल्ली *f.*, अश्मंतं, उद्धानं, उद्धानं, अधिश्रयणी, अंति(दि)का; 'f.-proof' अदाह्य; 'f.-side' अग्निस्थानं, &c. (f.-place). (f.-side comforts गृहसुखानि); 'f.-wood' इंधनं, इध्मं, दारुकाष्ठं; 'f.-works' अग्निक्रीडा,-द्रव्याणि. **—Fiery,** *a.* आग्नेय (यी *f.*), तेजस्विन्, अग्निमय (यी *f.*). 2 सुलभकोप, शीघ्रकोपिन्, कोपन, कोपिल, कोपशील, संरंभिन्. 3 उग्र, तीक्ष्ण, प्र-, चंड, तीव्र.

Firm, *a.* दृढ, स्थिर, निश्चल, अचल, अविचलित, अस्खलित, धीर, अकंपित, अक्षुब्ध, धृतिमत्, व्यवस्थित; 'f. step' अस्खलिता गतिः. **2** गाढ, घन, दृढ, अशिथिल, अविरल, सांद्र, सुसंहत, दृढसंधि; 'of a f. mind' स्थिरधी, स्थिर-निश्चल-मति, दृढात्मन्; 'f. in friendship' दृढसौहृद, गाढसख्य. **-***s.* वणिग्जनसंसर्गः, समवायः, संभूय समुत्थानं. **-ly,** *adv.* दृढं, गाढं, घनं, स्थिरं, धीरं, निश्चलं, &c.; 'f. rooted' बद्ध-रूढ-मूल; 'f. devoted' दृढभक्ति; 'f. joined' दृढबद्ध, दृढसंधि. **-ness,** *s.* दृढता, स्थैर्यं, द्रढिमन् *m.*, धैर्यं, धृति *f.*; अक्षोभः, अस्खलनं, अकंपः. **2** संहति *f.*, घनता, संधिः.

Firmament, *s.* आकाशः-शं, नभोमंडलं, नभस्तलं; व्योमन् *n.*, गगनं-णं, खं, अंतरीक्षं, तारा-उडु-पथः, खगोलः; *See* **Sky** also. **-al,** *a.* वैहायस (सी *f.*), आंतरीक्ष (क्षी *f.*), आकाशीय, नभःस्थ.

First, *a.* प्रथम, आद्य, आदिम, पूर्व, अग्रिम, प्राक्तन (नी *f.*). **2** मुख्य, प्रमुख, प्रधान, अग्र्य, प्रवर, श्रेष्ठ, वरेण्य, अग्रणी, अग्रेसर, वर in comp.; *See* **Principal,** 'f. half' पूर्वार्धः; 'f. part of day' पूर्वाह्णः; 'f. part of night' पूर्वरात्रः, 'for the f.time' प्रथमं; 'from the f.' प्रथमावधि, आप्रथमं; 'f. of all, in the first place' प्रथमं-आदौ-तावत्; 'f. born' अग्रजः, पूर्वजः, अग्रजन्मन् *m.*, ज्येष्ठः, अग्र्यः, :, अग्रिमः; 'f.-fruits' प्रथम-आदि-अग्र-फलं, प्रथमोत्पन्नं; 'f.-rate' श्रेष्ठ, उत्कृष्ट, विशिष्टतम, परम, उत्तम. **-***adv.*, **-ly,** प्रथमं, पूर्वं, प्राक्, आदौ, अग्रे, पुरस्तात्.

Fiscal, *a.* धनसंबंधिन्.

Fish, *s.* मत्स्यः, मीनः, झषः, वैसारिणः, अंडजः, विसारः, शकुलिन् *m.*, पृथुरोमन् *m.* **-***v. i.* मत्स्यान् ग्रह् 9 U or धृ 1 P or बंध् 9 P. **2** अनुसृ 1 P; 'f.-basket' मत्स्याधानी, कुवेणी; 'f.-hook' बडिशं-शा-शी, मत्स्यवेधनं; 'f.-ing net' जालं, आनायः, कुपिनी; 'f.-market' मीनविक्रयस्थानं; 'f.-monger' मत्स्यविक्रयिन्; 'f.-pond' मीनाश्रयः, मत्स्यालयः, मत्स्यपूर्णं सरः; 'f.-spawn' मत्स्यांडं; 'f.-woman' मत्स्यविक्रेत्री. **-er, -erman,** *s.* धीवरः, कैवर्तः, दासः-शः, जालिकः, मत्स्याजीवः, मत्स्योपजीविन् *m.*, मात्स्यिकः, निषादः. **-ery, -ing,** *s.* धीवरकर्मन् *n.*, मत्स्यबंधनं-ग्रहणं.

Fissile, *a.* भिदुर, भिदेलिम.

Fission, *s.* छेदः.

Fissure, *s.* छिद्रं, रंध्रं, संधिः, भंगः, विदलः-लं, भेदः; (in the ground) बिलं, गर्तः-र्ता, विवरं. **-***v. t.* विद् 10, विदल् c. (दलयति).

Fist, *s.* मुष्टि *m. f.*-ष्टी; 'fisticuffs' 'blows with the f.' मुष्टिघातः-प्रहारः-युद्धं, मुष्टीमुष्टि-युद्धं; 'doubling or clenching the f.' मुष्टिबंधः-संग्राहः, खटः. **-***v.* मुष्टीमुष्टि युध् 4 A, मुष्टिना तड् 10 or प्र-हृ 1 P.

Fistula, *s.* नाडि-डी-लि-ली *f.*, नाडीव्रणं, नाडीक्षतं; 'f. in anus' भगंदरः.

Fit, *a.* योग्य, क्षम, न्याय्य, अनुरूप, उपपन्न, युक्त, उचित, यथार्ह, समुचित, यथायोग्य, संगत; oft. by अर्ह् or pot. pass. part.; 'to be f. for' कॢप् 1 A (with dat.), युज्-उपपद् pass. अर्ह् 1P, उचित-योग्य-*a.* भू; 'f. to do a work' कर्मक्षम, अलंकर्मीण. **-***v. t.* युज् 7 U, 10, समा-सं-धा 3 U, योग्य-युक्त -*a.* कृ 8 U; 'f. an arrow' बाणं सं-धा; *See* **Fix**; 'this ill f. s thee' नैतद्भवदनुरूपं भवतः; 'f. out' सज्जीकृ, सन्नह् c., उपकरणैः उपकॢप् c., or संयुज् or उपस्कृ; 'fit up' **Decorate,** q. v. **-***v. i.* युज्-उपपद्-pass., श्लिष् pass., युक्त *a.* भू; 'this f. s well' सुश्लिष्टमेतत् (Mal. 1), सुसंगतमिदं. **-***s.* आक्रमः, आवेशः, अवतारः, अभिभवः, 'f.of anger' कोपावेशः; 'f. of fever' ज्वराक्रमः, ज्वराभिभवः. **2** मूर्छा, भ्रमि *f.*, भ्रामरं. **-ful,** *a.* चल, चपल, चंचल, अनित्य, विषम, लोल, अस्थिर. **-ly,** *adv* युक्तं, उचितं, सम्यक्, यथार्हं, सांप्रतं, स्थाने. **-ness,** *s.* युक्तता, योग्यता, क्षमता, पात्रता, उपयोगिता, उपपत्ति *f.*, संगति *f.*, पर्याप्ति *f.*, याथार्थ्यं, देशरूपं.

Fitch, *s.* चणकः.

Five, *a.* पंचन्, पंचक, पंचतय; 'in f. ways' पंचधा;, 'f. times' पंचकृत्वः; 'f. fold' पंचगुण *a.* **-Fifth,** *a.* पंचम (मी *f.*)

Fives, *s.* कंदुकक्रीडा.

Fix, *v. t.* स्था c. (स्थापयति), प्रति-सं°; निधा 3 U, निरुह् c.; 'f. your dwelling there' तत्र वसतिं कुरु, तत्स्थाने निवस. **2** स्थिरीकृ 8 U, दृढीकृ. **3** (F. upon) निर्णी 1 P, निश्चि 5 U, अव-धृ 10, निरूप् 10, संपरि-कॢप् c., निर्दिश् 6 P, नियुज् 7 A, 10. **4** बंध् 9 P (lit. & fig.), युज्, आसंज् c.; निविश् c.; 'did not f. her love on him' तस्मिन्न बबंध भावं (R. vi. 36); 'f. the eyes' दृष्टिं निविश् c., लक्ष्यं बंध्, अनन्यदृष्ट्या-अनिमेषेण-स्तिमितलोचनेन-दृश् 1 P; 'with his eyes f. ed on my face' मन्मुखासक्तदृष्टिः; व्यापृ c., उमामुखे व्यापारयामास विलोचनानि (K. III. 67); 'f. an arrow' सं-धा 3 U, (धनुष्यमोघं समधत्त बाणं K. III. 66); 'f. the mind' मनः-चित्तं-निविश् c.,or युज् or बंध् or आधा, एकाग्र *a.* भू; तेन उपदेशेन मम चेतसि दृढं पदं चक्रे 'the advice is firmly f. ed &c.'; 'I am in a f.' चक्रांतरस्थित इवास्मि. **-ed,** *a.* व्यवस्थित, स्थिरीकृत, स्थापित, प्रतिष्ठित, निरूढ. **2** नियत, निश्चित, ध्रुव, स्थिर,

दृढ, निश्चल, अचल; *See* **Firm.** **3** सक्त, आ-सं-सक्त, सं-परि-लग्न; निविष्ट, बद्ध. **4** स्थावर, अजंगम, ध्रुव; 'firmly f.' दृढबद्ध, बद्धमूल, प्रतिष्ठित, रूढमूल; 'having the gaze f.' 'with a f. look' आसक्त-बद्ध-दृष्टि, स्तिमित-अनिमेष-लोचन; 'having the mind f. (on one thing); एकाग्रचित्त, अनन्यमनस्क, निविष्ट-आसक्त-मनस्; एकतान, अनन्यवृत्ति, एकाग्र,एकायन,एकसर्ग,एकाग्रय, एकायनगत; 'of f. resolution' दृढ-निश्चय-संकल्प, धीर-स्थिर-मति, स्थिरधी. **-edly,** *adv* दृढं, स्थिरं, ध्रुवं, &c; स्थिर-दृष्ट्या, अनिमेषेण, स्तिमितं, एकाग्रतया, &c **-edness,** *s.* **Firmness,** q. v. **-ity,** *s.* स्थिरता, स्थैर्य, निष्ठा; 'the mind, devoid of f, rambles' मनो निष्ठाशून्यं भ्रमति (Mal. 1). **-ture,** *s* स्थावरद्रव्यं.

Flabby, *a.* शिथिल, ललित, कोमल, स्निग्ध, मेदुर, अकठिन. **-ness,** शैथिल्यं, लालित्यं.

Flaccid, *a. See* **Flabby.**

Flag, *s.* ध्वजः, केतुः, पताका; 'f.-staff' ध्वज-दंडः-यष्टिः-स्तंभः. **2** (Stone) शिलापट्टः-प्र-स्तरः. **-***v. i.* अवसद् 1 P, ग्लै-म्लै 1 P, ध्वंस् 1 A. अपचि-क्षि- pass. **2** (Of persons) शिथिलबल-अवसन्न-भग्नोत्साह *a.* भू, अंगानि मुच् 6 P; *See* **Droop.** **-***v. t.* शिलाभिः आस्तृ 5 U. **-gy,** *a.* शिथिल, क्षीण, अव-सन्न, श्लथ.

Flagellate, *v. t.* कशया तड् 10 or प्र-हृ 1 P or आहन् 2 U. **-ion,** *s.* कशाघातः, कशाप्रहारः.

Flageolet, *s.* वंशः, वेणुः.

Flagitious, *a.* घोर, दारुण, अतिदुष्ट, अतिदुर्वृत्त, अति-महा-पापिन्, अतिनिंद्य. **-ness,** *s* महा-अति-पापं-पातकं, अतिदुष्टता, घोरता, दौरात्म्यं.

Flagon, *s.* पानपात्रं-भाजनं, पुटग्रीवः, कंसः-सं.

Flagrant, *a.* घोर, दारुण, अतिदुष्ट, अति-निंद्य, पापिष्ठतम. **2** सर्वज्ञात, लोकप्रसिद्ध, सुप्रकाश, सुव्यक्त, पुरःस्फुरत्. **-Flagrancy,** *s.* घोरता, अतिदुष्टता; सुव्यक्तता.

Flail, *s.* मुसलः-लं, कंडनी.

Flair, *s. See* **Odour.**

Flake, *s.* हिम or तुषार-लवः or कणः, हिमतूलं, तुषार-हिम-घनः. **2** शकलः-लं, लवः, कणः, अल्पभागः. **3** फलकः, संस्तरः. **-***v. i.* शक-लीभू 1 P. **-y,** *a.* सशकल.

Flambeau, *s.* उल्का, अलातं, उल्मुकं.

Flame, *s.* ज्वाला, शिखा, अर्चिस् *f., n.*, कीलः-ला, अग्निज्वाला-जिह्वा; 'in f. *s*' ज्वलत्, हुतवहपरीत, दह्यमान. **-***v. t.* ज्वल् c., दीप् c., दह् c., **-***v. i.* ज्वल् 1 P, दीप् 4 A, दह् pass. **-ing,** *a.* उज्ज्वल, प्रदीप्त, अर्चिष्मत्, उज्ज्वल, ज्वलित, ज्वलत्; 'f. fire' ज्वालाग्निः. **-y,** *a.* शिखा-ज्वाला-मय (यी *f.*), शिखिन्.

Flamingo, *s.* मरालः, राजहंसः.

Flank, *s.* पार्श्वः-र्श्वं, पक्षः, कुक्षिः, उत्संगः, पार्श्व-पक्ष-भागः, पार्श्वगं. **-***v.* पार्श्वतः रक्ष् or गुप् 1 P. **2** पार्श्वतः अभिद्रु 1 P. **3** स्पृश् 6 P, निकटे-पार्श्वे-वृत् 1 A; *See* **Border.**

Flannel, *s* उर्णायुः, और्णपटं.

Flap, *v. t.* वि-धू 5 U, 9 U, 6 P, उत्क्षिप् 6 P, चल् c., आ-स्फल् c. **-***v. i.* आस्फल् 1 P, विधू-उत्क्षिप्-pass. **-***s.* प्रालंबः, लोलकः. **2** (f. ing) आस्फालनं, विधूननं, विधुवनं, उ-त्क्षेपः-पणं; 'f. ing of ears' कर्णतालः.

Flare, *v. i.* लोलशिखया ज्वल् 1 P. **-***s.* लोल-शिखा, कंपितज्वाला

Flash, *v. i.* स्फुर् 6 P, दीप् 4 A, वि-लस् 1 P, विद्युत् 1 A, सहसा प्रकाश् 1 A or ज्वल् 1 P, अचिरं प्र-भा 2 P. **2** विद्युद्वेगेन-अकस्माद्-उदि 2 P or आविर्भू 1 P or उत्पद् 4 A. **-***s.* स्फुरणं. स्फुरितं, विलासः, सहसा दीप्ति *f.*, आभासः, विभ्रमः, अचिर-क्षण-प्रभा, प्रभाकंपः, क्षणद्युति *f.*, अचिरद्युतिः. **-y,** *a.* क्षणप्रभ, तैजस (सी *f.*). **2** असार, नीरस, फल्गु, निःसत्त्व.

Flask, *s.* काचपात्रं-भाजनं, पानपात्रं, पुटग्रीवः.

Flat, *a.* सम, समस्थ, समरेख, सपाट, अमुग्र. **2** निम्न, अनुच्च, नत, अनुन्नत. **3** असार, नीरस, फल्गु, विरस, रस-स्वाद-हीन, निस्ते-जस्, निःसत्त्व. **4** स्पष्ट, स्फुट, व्यक्त, अवक्र, असंदिग्ध, सुव्यक्त, परिस्फुट. **5** अवनिं गत, दंडवत् क्षिप्त; 'he laid himself f. on the ground' भूमौ दंडवत्पतितः; 'f. surface' समपृष्ठं; 'f. roof' पृष्ठं; 'f.-nosed' अव-नाट, अवटीट, अवभ्रट, नत-चिपिट-नासिक. **-***s.* समभूमि *f*, समस्थलं-ली, समस्थानं, पाटः. **2** निम्नभूमिः. **3** सैकतं, पुलिनं. **4** पत्रं, फलकः-कं. **5** मंद्रः, अनुदात्तः, मंद्रः. **-ly,** *adv.* समं. **2** स्फुटं, सुव्यक्तं, अवक्रं, असंदेहं. **-ness,** *s.* समता, निम्नता, असारत्वं, &c. **-ten,** *v. t.* समीकृ 8 U. **2** आ-अव-नम् c. (नमयति), नम्रीकृ, निम्नीकृ. **3** रसं हृ 1 P, नीरसीकृ. **-***v. i.* समीभू, नम्रीभू.

Flatter, *v. t.* सं-अभि-परि-स्तु 2 U, प्र-शंस् 1 P, चाटुवचनैः-स्तुत्या-सांत्व् 10 or संतुष् c. or उप-लल् 10 or प्र-लुभ् c. or आकृष् 1 P, उपच्छंद् 10. **2** चाटूनि वच्-ब्रू- 2P, प्रियं वद् 1 P. **3** अनु-नी 1 P, आ-राध् c., मिथ्या प्र-शंस् श्लाघ् 1 A. **4** मिथ्या आशां उत्पद् c. or वृध् c. **-er,** *s.* चाटुकारः, संस्ताव-कः, सांत्ववादिन् *m.*, प्रशंसकः, प्रियंवदः, चाटुवादिन् *m.*, मिथ्याशंसकः. **-ing,** *a* स्तुति-मय (यी *f.*), परितोषक, प्रीतिकर (रि *f.*), प्रशंसामय. **-ingly,** *adv.* चाटूक्त्या, अति-प्रशंसापूर्वं, सांत्वनपूर्वं. **-y,** *s.* संस्तावः, स्तुति *f.*

स्तवः, चाटु m.-n., चाटूक्ति f., अतिप्रशंसा, सांत्वनं-ना, उपलालनं, मधुर-प्रिय-वचनं, सांत्ववादः, मिथ्याप्रशंसा, व्याजस्तुतिः, चाटुवादः. 2 अनुनयः, आराधनं, संतोषणं.

Flatulent, *a.* वात-वायु-ग्रस्त, बद्धवात, वातफुल्ल, वायुपूर्ण, वातुल. **–Flatulence, –cy,** *s.* वायुः, वातः, वायुफुल्लता, अंत्राध्मानं, वातिकत्वं.

Flatus, *s.* वातः, वायुः, अंत्रवायुः.

Flaunt, *v. i.* सावलेपं चर्-चर् 1 P, सदर्प-उद्धत-विकटं-परिक्रम् 1 U, 4 P. **–ing,** *a.* उद्धतगति, विलासाद् मंदगामिन्-दर्शनीयमानिन्, शुभंमन्य; 'a f. gait' विकटा-धीरोद्धता-गतिः.

Flavour, *s.* आ-,स्वादः, रसः, रुचि *f.* **–v. t.** सरस *a.* कृ 8 U. **–ed,** *a.* सरस; 'well- f.' सुरस, स्वादु, सुस्वाद. **–less,** *a.* अरस, नीरस, विरस, अस्वादु. **–ous,** *a.* मिष्ट, स्वादु, सुरस.

Flaw, *s.* दोषः, छिद्रं, रंध्रं, वैकल्यं, न्यूनता; 'seeking or finding f. s' रंध्रान्वेषिन्, छिद्रान्वेषिन्, दोषैकदृश्. 2 चंडवातः, प्रभंजनः; *See* **Hurricane.** 3 भंगः, संधिः, भेदः, रंध्रं, छिद्रं; 'f. in a jewel' पुलकः, खंडः. **–v. t.** छिद्र 10, व्यच्, 4 P. **–less,** *a.* निर्दोष; *See* **Faultless.** 2 निश्छिद्र, नीरंध्र. **–y,** *a.* सरंध्र, सच्छिद्र, सदोष.

Flax, *s.* क्षुमा, अतसी, उमा; शणं; 'f.-comb' उमामार्जनी. **–en,** *a.* क्षौम-औम (मी *f.*).

Flay, *v. t.* चर्म अपनी or निर्हृ 1 P or उल्लिख् 6 P or निष्कुष् 1 P, निस्त्वचयति (D.), निस्त्वचीकृ 8 U, त्वक्ष् 1 P. **–er,** *s.* त्वग्निदारकः, चर्मनिष्कर्षकः. **–ing,** *s.* चर्मनिष्कर्षणं, निश्चर्मकरण.

Flea, *s.* मक्षिका, मत्कुणः, देहिका, तल्पकीटः. **–v. t.** देहिकाः अपनी 1 P.

Fleck, *s.* रे(ले)खा, बिंदु *m.*

Fledged, *a.* संजातपत्र, गरुत्मत्, सपक्ष, पक्षयुक्त.

Flee, *v. i.* पलाय् 1 A, अपक्रम् 1 U, 4 P, वि-प्र-द्रु 1 P, परा-इ 2 P, अपधाव् 1 P, अप-निर्-गम् 1 P, अप-सृ-सृप् 1 P. 2 त्यज् 1 P, परिहृ 1 P, वृज् 10.

Fleece, *s.* मेषलो(रो)मन् *n.* **–v. t.** (लोम) छिद् 7 P or लू 9 U. 2 अपहृ 1 P; 'f. ed' हृतसर्वस्व. **–cy,** *a.* बहुलोमन्, लोमश, लोमावृत.

Fleer, *v. t.* अव-उप-हस् 1 P, तिरस्कृ 8 U, अवमन् 4 A, अव-ज्ञा 9 U; *See* **Contemn.** **–s.** उप-अव-हासः; तिरस्कारः, अवहेलना, अवज्ञा.

Fleet, *s.* नौसमाजः-साधनं, पोतावलि *f.*, युद्धनौसमूहः. **–v. i.** द्रुतं-शीघ्रं-प्रसृप् 1 P or गम् 1 P, वेगेन चल् 1 P, त्वर् 1 A. **–a.** वेगवत्, शीघ्र-त्वरित-लघु-गति, प्रजाविन्, अतिरंहस्, जवन (नी *f.*), शीघ्रगामिन्, महाजव; 'f. as the wind' वायुगति, वायुवेग; 'f. as thought' मनोजव. **–ing,** *a.* क्षणिक, क्षणभंगुर, अध्रुव, क्षणस्थायिन्; *See* **Fickle.** **–ly,** *adv.* द्रुतं, शीघ्रं, लघु, सत्वरं, जवेन, वेगेन, रंहसा. **–ness,** *s.* वेगः, प्र-,जवः, रंहस् *n.*, त्वरितगति *f.*

Flesh, *s.* मांसं, आमिषं, पिशितं, क्रव्यं, तरसं, पललं; 'dried f.' वल्लूरं-रा, उत्तप्तं, शुष्कं मांसं. 2 शरीरं, विषयसेवा, विषयासक्ति *f.*; 'f. diet or meat' मांसाहारः; 'f.-colour' मांसवर्णः-रागः-लोहि- 'f.-monger' मांसविक्रयिन् *m.* **–less,** *a.* अमांस, अपुष्ट, मांसहीन. **–ly,** *a.* शारीरिक-दैहिक (की *f.*), विषयिन्, सांसारिक-ऐहिक (की *f.*). **–y,** *a.* मांसल, पुष्ट, पीन, पीवर, मेदस्विन्; *See* **Fat.**

Flexible, *a.* आ-,नम्य, कुंचनीय, नमन-कुंचन-शील, कोमल, मृदु, आयम्य. 2 अनुनेय.

Flexion, Flexture, *s.* आ-,नति *f.*-नमनं; भंगः, आ-अव-कुंचनं, वक्रता, वक्रिमन् *m.*

Flexuous, *a.* वक्र, कुटिल, जिह्म, भंगुर.

Flick, *v. t.* आहन् 2 P, प्रहृ 1 P, आस्फाल् 10. **–s.** *See* **Flip.**

Flicker, *v. i.* चल् 1 P, चंचलतया ज्वल् 1 P, लोलशिखया ज्वल्, चंचलीभू 1 P. 2 पक्षौ आ-स्फल् c. **–ing,** *a.* चल, चंचल, अस्थिर, लोल. **–s.** चंचलशिखा, चलनं, चांचल्यं.

Flimsy, *a.* असार, फल्गु, सारहीन, निर्बल, निःसत्त्व, अल्पबल, क्षीणशक्ति. **–ness,** *s* असारता.

Flinch, *v. i.* विमुखी-पराङ्मुखी-भू 1 P, विचल् 1 P, नि-परा-वृत् 1 A, (abl.); पलाय् 1 A, त्यज् 1 P, त्यक्त्वा निर्गम् 1 P or अपसृप् 1 P मुखं परा-वृत् c. **–ing,** *s.* निवर्तनं, वैमुखता, विचलनं, विमुखीभवनं.

Fling, *v. t.* (सहसा-बलेन) क्षिप् 6 P, अस् 4 P, मुच् 6 P, वि-सृज् 6 P, पत् c., ईर् c.; 'f. away or off' अप-क्षिप्, निरा-कृ, अपास्, अप-हा 3 P; 'f. open' सहसा or बलाद् अपावृ 5 U. **–s.** क्षेपः-पणं, पातः-तनं; प्रक्षेपः.

Flint, *s.* अरणिः, अग्निग्रावन् *m.*, अग्निप्रस्तरः. **–y,** *a.* अग्निप्रस्तरमय (यी *f.*). 2 कठिनहृदय, पाषाणहृदय.

Flip, *s.* आघातः, प्रहारः, आस्फालनं.

Flippant, *a.* वाचाल, वावदूक, निःसार, वाक्चंचल. 2 चपल, अस्थिर, लोल, चंचल. **–ly,** *adv.* वाक्चापल्येन. **–Flippancy,** *s.* वाक्चापल्यं वावदूकता; निःसारता. 2 प्रगल्भता, लौल्यं, चांचल्यं.

Flirt, *v. t.* सहसा क्षिप् 6 P. **–v. i.** अव-हस् 1 P, अधिक्षिप् 6 P. 2 विभ्रम् 1, 4 P, विलस् 1 P, विलासं-विभ्रमं-कृ c. 3 चल *a.* भू 1 P, स्पंद् 1 A, कंप् 1 A, स्फुर् 6 P. **–s.**

आकस्मिकक्षेपः. 2 विलासिनी, लीलावती, चपला, प्रगल्भा. **–ation,** *s.* लीला, हेला, विभ्रमः, विलासः, हावः, खेला, प्रेमलीला. 2 स्पंदनं, स्फुरणं; हृदयकंपः.

Flit, *v. i.* लघु चल् 1 P, द्रुतं वि-प्र-सृप् 1 P, स्थानात्स्थानं भ्रम् or चल् 1 P, इतस्ततो भ्रम् 1, 4 P. 2 प्र-उत्-डी 1, 4 A, व्योम्नि विसृप्, चपलीभू. **–ting,** *s.* भ्रमणं, चलनं, लघु सर्पणं.

Flitch, *s.* वल्लूरं, शूकरोत्तरं.

Flitter *s.* चीरं, कर्पटः, वस्त्रखंडः-डं.

Flittermouse, *s.* जतुका, अजिनपत्रा.

Float, *v. i.* प्लु 1 A; तॄ 1 P. 2 भास् 1 A. **–v.** *t.* प्लु c., वह् c. **–s.** प्लवः, उडुपः, कोलः, वहित्रं, तरणः-णी, तरीः.

Flocculent, *a.* सांद्र, घनीभूत, श्यान.

Flock, *s.* यूथं, संघः, निवहः, समूहः, कुलं, गणः; *See* **Multitude**; 'f. of cattle' पाशवं, पशुकुलं, गो-वृंदं-कुलं, 'f. of sheep' अविकुलं, आविकं; 'f. of sheep and goats' अजाविकं; 'in f. s' गणशः, संघशः. **–v.** *i.* (Together) संघशः-गणशः-समागम् 1 P or मिल् 6 P or संनि-पत् 1 P, एकत्र मिल्, एकीभू.

Flog, *v. t.* कशया-वेत्रेण-तड् 10 or आ-हन् 2 U or दंड् 10 or प्र-हृ 1 P. **–ging,** *s.* कशाघातः, कशाप्रहारः; 'deserving f.' कश्य.

Flood, *s.* पूरः, ओघः; स्रोतस् *n.*, प्रवाहः, रयः. 2 आप्लवः, संप्लवः, तोयविप्लवः, जलप्रलयः, जलोपप्लवः; 'universal f.' महाप्रलयः, भूतसंप्लवः, संवर्तः. 3 प्राचुर्यं, बाहुल्यं, पूरः, ओघः; 'f. of tears' बाष्पपूरः-ओघः-वर्षः, अश्रुपातः-वर्षः, 'f.-gate' द्वारं, निर्गममार्गः, परि(री)वाहः, जलद्वारं, जलनिर्गमः. **–v.** *t.* प्लु c., आ-सं-परि°-, परिवह् c.; 'with her eyes f.-ed with tears' अश्रुपरिप्लुतेक्षणा; 'a f.-ed river' आप्लुतोदका-परिवाहिणी-नदी.

Flook, *s.* हलदंतः.

Floor, *s.* भूमि *f.*, भूपृष्ठं, तलं, भूतलं, गृहभू-भूमि *f.*, गृहपोटः, वास्तु *m. n.*, गृहमूलं, वेश्मभूः. 2 (Story) भूमिः, कोष्ठः; 'a palace havaing 7 f.s' सप्तभूमिकः प्रासादः; 'the upper f.' उपरिभूमिः. 3 फलकास्तरणं, फलकसंस्तरः, फलकः-कं. **–v.** *t.* फलकैः आ-स्तॄ 9 U or आच्छद् 10. 2 नि-पत् c., भूमौ क्षिप् 6 P.

Flop, *v. t.* आ-स्फल् c.

Flora, *s.* ओषधिजातं.

Floral, *a.* कौसुम (मी *f.*), पुष्प in comp.

Florid, *a.* रक्त, रक्त-अरुण-वर्ण. 2 अलंकृत, उज्ज्वल, अलंकारशोभित, सालंकार. **–ity, –ness,** *s.* (कपोल)-रागः, अरुणिमन्-रक्तिमन् *m.* 2 वागलंकारः, सालंकारत्वं, अलंकारशोभा.

Floriferous, *a.* पुष्पोत्पादक, पुष्पप्रद.

Florilego, *s.* पुष्पचयः-संघः.

Florist, *s.* मालाकारः, पुष्पविद्याज्ञः.

Flota, *See* **Fleet.**

Flotilla, *s.* लघुनौसमूहः,

Flounce, *v. i.* अंगानि विक्षिप् 6 P or इतस्ततः चल् c. **–s.** आकस्मिकः अंगविक्षेपः.

Flounder, *v. i.* इतस्ततः क्षिप् pass., लुठ् 1 A, 6 P, वि-हृ 1 A. 2 वि परि-भ्रम् 1, 4 P.

Flour, *s.* गोधूमचूर्णं, चूर्णं, क्षोदः, पिष्टं, गुंडिका, सक्तवः (pl.).

Flourish, *v. i.* सं-जन् 4 A, सं-भू 1 P; 'when Panini f. ed' यदा पाणिनिः समभवत. 2 वृद्धिं-उन्नतिं-गम् 1 P, सं-ऋध् 4, 5 P. एध् 1 A, सं-वि-वृध् 1 A, प्र-उप-चि pass. स्फाय् 1 A **–v.** *t.* वृध् c. 2 चित्र् 10, पुष्पादिना अलंकृ 8 U or शुभ् c. or रंज् c. 3 भ्रम् c. (भ्रमयति), घूर्ण् c. **–s.** आडंबरः, शोभा, अलंकारः, मंडनं. 2 निः-,स्वनः (of trumpets). 3 दर्पवाक्यं, गर्वोक्ति *f.* 4 भ्रमणं, उद्गमः. **–ing,** *a.* समृद्ध, सुस्थित, सुस्थ, वर्धिष्णु, उदयिन्, उपचीयमान.

Flout, *See* **Contemn.**

Flow, *v. i.* प्र-,स्रु 1 P; प्र-नि-अभि-स्यंद् 1 A, क्षर् 1 P, गल् 1 P, सृ 1 P; प्रवह् 1 P, री 4 A, द्रु 1 P; 'f. ing with tears' बाष्पजलनिस्यंदिन्; 'f. ing with nectar' सुधास्यंदिन्, अमृतस्रुत्; प्र-,स्नु 2 P; 'f. ing (of milk)' प्रस्रवः. 2 प्र-सृप् 1 P, प्र-सृ, प्रवृत् 1 A, प्र-गम्-चल् 1 P, प्र-या 2 P. 3 जन् 4 A, उत्पद् 4 A, उत्-प्र-सं-भू 1 P, प्रवृत्. 4 स्रंस् 1 A, शिथिलीभू, श्लथ-वितत-गलित *a.* भू. **–s.** स्रवः, स्रवणं, स्रुति *f.*, स्रावः, क्षरणं, गलनं, प्रवृत्ति *f.*, अभि-नि-स्यं(स्यं)-दः-दनं. 2 प्रवाहः, स्रोतस् *n.*, ओघः, प्रस्रवः, वेगः, रयः, धारः-रा; वेला, पद्धति *f.* 3 समुद्रवेला, वेला; 'f. of tears' अश्रुपातः-प्रवाहः, बाष्पवर्षः, धाराम्बु *n.*; 'f. of words' वाग्ओघः. अप्रतिहता वाक्सरणिः-पद्धतिः. **–ing,** *a.* प्रस्रुत, स्यंदिन्, विसारिन्, स्रवत् 2 अप्रतिहत, अस्खलित; 'a f. delivery' अस्खलितभाषण-पद्धतिः. **–ingly,** *adv.* अस्खलितवाक्येन, अप्रतिहतं, द्रुतं, अविलंबितं.

Flower, *s.* पुष्पं, कुसुमं, प्रसूनं, सुमं, सूनं, सुमनस् *f.* (pl.) 2 अवतंसः, ललामभूतः, अलंकारः, तिलकभूतः; 'Rama is the f. of his class' स्ववर्गललामभूतो रामः. 2 सारः, उत्कृष्ट-श्रेष्ठ-भागः, उत्तमांशः, सारांशः; 'f. of age' यौवनं; 'f. of youth' नवयौवनं; 'being in the f. of youth' आरूढयौवनारंभ, प्रौढयौवन. **–v.** *i.* फुल्ल् 1 P, विकस् 1 P, स्फुट् 6 P, भिद् pass. 2 मंदायते-केनायते (D.). **–v.** *t.* पुष्पादिना अलंकृ 8 U or

क्षुभ् c. **-ed,** *a.* कुसुमित, पुष्पित, कुसुमसनाथ. 2 विकसित, फुल्ल, स्फुटित. **-ing,** *a.* पुष्पवत्, कुसुमवत्, कुसुमित, प्रफुल्ल, स्फुटितपुष्प. 2 पुष्पद. **-less,** *a.* अकुसुम, कुसुमहीन. **-y,** *a.* पुष्प-कुसुम-मय (यी *f.*), सपुष्प, सकुसुम, पुष्पशालिन्; gen. ex. by (*s.*) in comp.; 'f. arrows' कुसुमशराः. 2 सालंकार, अलंकृत, अलंकारयुक्त, मंडित.

Fluctuate, *v. i.* इतस्ततः चल् 1 P or घूर्ण् 1 A, लुल् 1, 6 P, विलुट् 1 A, 6 P. 2 दोलायते (D.), विकल्प् 1 A, संदिह् 2 U, विचल्, अस्थिर-चंचल *-a.* भू 1 P. **-ing,** *a.* दोलायमान, अस्थिर, चंचल, अनवस्थित, लोल, तरल, चल. **-ion,** *s.* अस्थैर्यं, चलता, अप्रतिष्ठा, चांचल्यं, विकल्पः, संदेहः, अनवस्थिति *f.*, आंदोलनं.

Flue, *s.* धूममार्गः-पथः.

Fluent, *a.* अस्खलितवाच्, अस्खलद्वाक्य, वाक्पटु, द्रुत-त्वरित-वाच् (of persons): अनर्गल, अप्रतिहतौघ, अविश्रांत, अस्खलित, द्रुत, अप्रतिहत, अनवरत. **-ly,** *adv.* अस्खलितवाचा, द्रुतवाक्येन, अस्खलितं, द्रुतं, अप्रतिहतं, वाग्विभवेन. **-Fluency,** *s.* वाक्पटुत्वं, वाक्चापल्यं, वाग्विभवः, ओघः, अनर्गलता, अप्रतिहतत्वं.

Fluid, *s.* द्रवः, रसः, द्रववस्तु *n.* **-a.** द्रव, विलीन, द्रुत; *See* **Liquid. -ity,** *s.* द्रवता, विलयः

Flummery, *s.* मिथ्याप्रशंसा-स्तुति *f.*

Flunky, *s.* दासः, चेटः, नीचकर्मकरः.

Flurry, *See* **Agitate.**-*s.* संभ्रमः, व्यग्रता, मोहः.

Flush, *v. t.* अरुणीकृ 8 U, अरुणयति (D.), रंज् c., रक्तीकृ; 'with her face f. ed with anger' कोपारुणिताननाः. 2 उत्सिच् c., दृप् c., दर्पेण आ-ध्मा 1 P, उद्धतीकृ. *-v. i.* अरुणीभू, रक्तीभू, लोहितायते (D.), रंज् pass.; अरुणवदन-लोहितानन-*a.* भू. **-s.** अरुणिमन् *m.*, रक्तिमन् *m.*, रक्तता, रागः, कपोल-वदन-रागः. 2 प्रफुल्लता, बाहुल्यं, समृद्धि *f.* **-a.** सतेजस्क, प्रौढ, तेजस्विन्. 2 समृद्ध, धनसंपन्न. 3 मुक्तहस्त, अतिव्ययपर. **-ed,** *a.* अरुणित, रक्त, लोहित. 2 उद्धत, दृप्त, दर्पाध्मात, उत्सिक्त, गर्वित, सावलेप.

Fluster, *v. t.* पानादिना मद् c. or मुह् c. **-s.** चित्तभ्रमः, उन्मादः, मोहः, व्याकुलता.

Flute, *s.* वेणुः, मुरली, वंशः **-v. i.** 'Blow a f.' (वेणुं) मुखमारुतेन पूर् 10 or वद् c., ध्मा 1 P: 'f.-player' वैणविकः, वेणुध्माः, वांशिकः.

Flutter, *-v. i.* पक्षौ वि-धू 5, 9 U, 6 P or आस्फल् c. or उत्क्षिप् 6 P or विचल् c. 2 इतस्ततः चल् 1 P or धाव् 1 P or प्र-सृ 1 P. 3 कंप् 1 A, स्फुर् 6 P, उच्छ्वस् 2 P, स्पंद् 1 A, क्षुभ् 4 P. *-v. t.* संक्षुभ् c., आकुलीकृ 8 U, स्पंद् c., कंप् c., स्फुर् c. **-s.** विधुननं, आस्फालनं, उत्क्षेपणं. 2 विकंपः, स्फुरणं, स्पंदनं, उच्छ्वसनं. 3 सं-,क्षोभः, संभ्रमः, सं-आ-वेगः, चित्तवेगः- भ्रमः. **-ing,** *s.* पक्षास्फालनं, पक्षचालनं. *-a.* विचल, कंपमान; 'f. in the breeze' अनिलोद्धूत, पवनाक्षिप्त, पवनाधूत.

Fluvial, *a* नदीसंबंधिन्.

Flux, *s.* (Fluxion) प्रवाहः, प्र-,स्रवः, क्षरणं. गलनं, स्पंदनं. *-v. t.* वि-द्रु c., वि-ली c. **-ible,** *a.* द्राव्य, गलनीय.

Fly, *s.* मक्षिका, वर्वणा, नीला; 'f.-flap' अवचूलकः, रोमगुच्छः, 'f. leaf' मलपृष्ठं. *-v. i.* उद्-,डी 1, 4 A, उत्-पत् 1 P, खे विसृप् 1 P, आकाशेन या 2 P or गम् 1 P. 2 अप-या 2 P, वि-प्र-द्रु 1 P, पलाय् 1 A; *See* **Flee.** 3 त्वरितं-शीघ्रं गम् or चल् 1 P or विसृप् or अतिक्रम् 1 U, 4 P. *-v. t.* त्यज् 1 P, परिह्र 1 P, वृज् 10. 2 आकाशे निक्षिप् 6 P or विसृप् c. or विसृ c.; 'f. at' आ-अभि-पत्, आ-अभि-द्रु, आ-अभि-प्र-धाव् 1 P; 'let f.' मुच् 6 P, उत्पत् c., विसृज् 6 P. **-ing,** *s.* डयनं, विसर्पणं, उत्पतनं; 'f. up and down' डीनावडीनं. *-a.* खविसर्पिन्, आकाशगति, आकाशगामिन्, डयमान, नभोगति; f. bridge' चलसेतुः, जंगमसेतुः, **-Flight,** *s.* पलायनं, विद्रावः, अपयानं, अपक्रमः-मणं, अपगमः; 'to put to f.' विद्रु c.; 'put to f.' विद्रुत, विद्रावित, कांदिशीक. 2 (Of birds) डयनं, डीनं, उड्डयनं, उत्पतनं, उद्गमनं; 'downward f.' अवडीनं. 3 पक्षि-माला-श्रेणी. 4 मति-बुद्धि-विलासः; 'f. of steps' सोपानपंक्ति-श्रेणि -णी *f.*, सोपानपरंपरा; 'f. of an arrow' शरपातः. **-y,** *a.* चलबुद्धि, भ्रांत-लोल-मति; अस्थिर, लोल; *See* **Fickle.**

Foal, *s.* किशोरः, अश्वशावः-वकः, बालघोटकः, अंबरीषः.

Foam, *s.* फेनः-णः. 2 मंडः, उत्सेकः; 'snowy f.' हिमधवलं, फेनपटलं. *-v.i.* फेनायते-मंडायते (D.), फेनं उत्पद् c. or निर्गम् c. (गमयति), उत्सिच्-उत्पीड्-pass. **-y,** *a.* फेनिल, फेनल, फेनयुक्त, फेनिन्.

Fob, *s.* घटीपिधानं-कोशः. *-v. t.* **Cheat,** q. v.

Focus, *s.* केंद्रं. *-v. t.* एकत्रीकृ 8 U.

Fodder, *s.* घासः, यवसं, पशुभोजनं, तृणादि *n.*

Foe, *s.* शत्रुः, अरिः, रिपुः; *See* **Enemy.**

Foetus, *See* **Fetus.**

Fog, *s.* कुहेडिका, कुहा, धूमि(पि-लि)का, कुज्झटिका, कुज्झटि-टी *f.* **-gy,** *a.* कुहावृत, धूमल, सधूमिक, कुज्झटिकाच्छन्न, धूमिकावृतमय (यी *f*).

Foible, *s.* छिद्रं, दोषः, अपराधः, न्यूनता, हीनता, वैकल्यं, अगुणः.

Foil, *v. t.* परा-भू 1 P, परा-जि 1 A; भंज् 7 P; व्या-प्रति-हन् 2 P, खंड् 10, परास् 4 U, मोघी-विफली-कृ 8 U. **2 Blunt,** q. v. —*s.* भंगः; व्याघातः; पराभवः. **2** मिथ्याखड्गः, निर्धार खड्गः. **3** पत्रं; 'golden f.' स्वर्णपत्रं. **4** प्रभा-वर्धकं, कांति-शोभा-वर्धकं. **—ed,** *a.* (Of persons) भग्नोद्यम, खंडिताश, हताश, अकृतार्थ; *See* **Disappointed. 2** (Of efforts &c.) भग्न, प्रतिहत, मोघीभूत, खंडित.

Foin, *s.* यष्टि-खड्ग-आघातः. —*v. t.* यष्टिना प्रहृ 1 P or तड् 10.

Foist, *v. t.* कपटेन लिख् 6 P or निविश् c., मिथ्या क्लृप् c., कृत्रिम *a.* कृ 8 U.

Foistiness, *s.* पूतिगंधिता.

Fold, *v. t.* पुटी-गुणी-कृ 8 U, व्यावृत् c., संपीड् 10, पुटयति (D.); 'f. ed thrice' त्रिगुणीकृत; 'f. ing his hands together' हस्तौ समानीय (R. II. 64), अंजलिं बद्ध्वा, कृतांजलिः, सां(प्रां)जलिः. **2** संवृ 5 U, पि-धा 3 U, आ-वेष्ट् c., आच्छद् 10. **3 Embrace,** q. v.; 'f. ing her in his arms' भुजाभ्यां तामापीड्य. **4** व्रजे निरुध् 7 U or निविश् c. —*s.* पुटः-टं, भंगः, व्यावृत्ति *f.* व्यावर्तनं; चूणः, वस्त्रभंगः-पुटः, ऊर्मि *f.* **2** व्रजः, अवरोधः, शाला, गोष्ठं; 'cattle-f.' गोव्रजः; 'sheep-f.' मेषगोष्ठः-गोस्थानं, व्रजाजिरं. **3** (In comp.) ex. by गुण; 'eight-f.' अष्टगुण; 'f. ing doors' द्विपक्षद्वारं.

Foliage, *s.* पल्लवः-वं, किसलयः-यं, पर्णं, दलं, पत्रं (gen. used in pl.); पल्लवगुच्छः-चयः.

Foliate, *a.* पर्णावृत, सदल.

Folio, *s.* पुस्तकपत्र, पृथु-विशाल-पत्रं.

Folk, *s.* जनः, जनसमूहः, जनता, लोकः; 'old f.' वृद्धजनः, वृद्धाः.

Follow, *v. t.* अनु-गम्-व्रज्-सृ 1 P, अनुबंध् 9 P, अनु-इ-या 2 P, अनुचर् 1 P, अनुक्रम् 1 U, 4 P. **3** सेव् 1 A, अनुष्ठा 1 P, आ-स्था 1 A; अनुवृत् 1 A, आश्रि 1 U, पुरस्कृ 8 U, अनुवि-धा 3 U, अनुरुध् 4 A, अनुसृ; 'f. (in) the footsteps of the great' महतां पदमनुविधेयं; 'f. ing the path' पदवीं प्रतिपद्य; 'f. ing a middle course' पुरस्कृतमध्यमक्रमः (R. VIII. 9); 'one misfortune f. s another' दुःखं दुःखानुबंधि (V. 4) ,विपद्विपदमनुबध्नाति (Ka. 73.) **3** उपास् 2 A, भज् 1 U, आश्रि, परिचर्; श्रु desid, (शुश्रूषते). —*v. i.* उत्पद् 4 A, प्राप्-आपद्-सिध्-अनुमा-pass. ; परिच्छिन्नस्ताव-ज्जीव इति प्राप्नोति (S. B. 651) it f. s' therefore &c.'; 'what f. ed is understood' परस्तादवगम्यते (S. 1); (in conversations) ततस्ततः; 'what f. ed next'; 'as f. s' तद्यथा, तद्यथानुश्रूयते, or merely एवं, इति, उक्तप्रकारेण, इत्थं. **—er,** *s.* अनुयायिन्-गामिन्-वर्तिन्-सारिन् *m.* **2** परिजनः, सेवकः, अनु-उप-जीविन् *m.*, अनुगः, अनुचरः, अनुयायकः, अनुप्लविकः, परिवारः, सहचरः, सहायः. 3 आश्रितः, भक्तः, अनुषंगिन् *m.* **—ing,** *a.* इदं-एतद् *pron. a.*; 'the f. story' एषा-इयं-कथा; पश्चात् कीर्त्यमान, अनुग, अनुयायिन्. —*s.* अनुसरणं-यानं-गमनं-वृत्ति *f.*-रोधः-वर्तनं.

Folly, *s.* *See* under **Fool.**

Foment, *v. t.* (उष्णोदकादिना) सं-सिच् 6 P, लिप् 6 P, अंज् 7 P, दिह् 2 U; स्विद् c. **2** उद्दीप् c., प्र-सं-वृध् c., उत्तिज् c., प्रोत्सह् c., उत्तप् c., प्रकुप् c., प्रवृत् c.; 'f. disputes' उप-जप् 1 P, भेद् वृध् c., भेद-बीजं वप् 1 P. **—ation,** *s.* प्र-,स्वेदनं, घर्मानुलेपनं, द्रवस्वेदः. **2** उद्दीपनं, संवर्धनं, उत्तेजनं, प्रवर्तनं. **—er,** *s.* उपजापकः, भेदकरः.

Fond, *a.* वत्सल, अनुरागवत्, सानुराग, अनुरक्त, प्रणयिन्, अनुरागिन्. **2** सेविन्, अभिलाषिन्, आसक्त, रक्त, रत, पर, तत्पर, gen. in comp. **3** मूढ, मुग्ध, अत्यनुरक्त; 'f. of' ex. by शील, लालस, काम, प्रिय, in comp.; oft. by ईह् 1 A, कांक्ष् 1 U, अभिलष् 1, 4 P, भज् 1 U, सेव्-रुच् 1 A; 'f. of sport' क्रीडाप्रिय; 'f. of chase' मृगयाशील; 'f. of change' अवस्थांतरमीहमान; 'f. of drinking' पानासक्त, पानव्यसनिन्. **—ly,** *adv.* सानुरागं, सप्रेम-मं; अतिस्नेहेन, अतिवत्सलत्वेन. **—ness,** *s.* अनुरागः, आसक्ति *f.*, रति *f.*, प्रीति *f.*, प्रणयः, स्नेहः; 'ingenious f. for the mate' कांतानुवृत्तिचातुर्यं; प्रेमन् *m.*, *n.*, वात्सल्यं; अभिरुचि *f.*, कामः, इच्छा, ईहा.

Fondle, *v. t.* उप-लल् 10, अंके-पा c. (पालयति), क्रोडीकृ 8 U, आलिंग् 1 P, परिष्वंज् 1 A, आ-सं-पीड् 10; 'f. ed too much' दुर्ललित. **—ing,** *s.* उप-,लालनं, आलिंगनं, भुजापीडनं, परिष्वंगः. **2** प्रेम-स्नेह-पात्रं-भाजनं, स्नेहभूमि *f.*

Food, *s.* अन्नं, आहारः, भोजनं, भोज्यं, भक्ष्यं, खाद्यं, खादनं, भक्षणं, अभ्यवहार्यं; भक्तं, विघसः, ग्रासः, अशनं, अंधस् *n.*; cooked f.' ओदनः-नं; 'f. and raiment' ग्रासाच्छादनं, अन्नवस्त्रं; 'forbidden f.' अभक्ष्य.

Fool, *s.* मूर्खः, मूढः, निर्बुद्धिः, अज्ञः, जडः, मंदः, अबुधः, अप्राज्ञः, प्रज्ञाहीनः, स्थूल-जड-धीः, अल्प-धीः-मतिः, मंद-धीः-मतिः, अनात्मज्ञः, वर्वरः; 'make a f. of' उपहासास्पदं कृ 8 U, विडंब् 10, (एवं प्रार्थयिता विडंब्यते S. 2). —*v. t.* मुह् c., वि-प्र-लुभ् c., वंच् 10; *See* **Cheat;** 'f.-hardy' अतिसाहसिक, व्यामूढ, अविमृश्यकारिन्, अविमृश्य प्रगल्भ, प्रमत्तवीर, प्रमत्त. **—ery,** *s.* प्रहसनं,

विडंबना. 2 बालिश्यं, मूर्खक्रिया, बालिशता, मूर्खता, व्यामोहः. **-ish**, *a.* मूर्ख, मूढ, बालिश, अनात्मज्ञ, दुर्मति, दुर्मेधस्, वैधेय, बालिशमति, निर्बुद्धि, जड, स्थूलधी, प्रज्ञा-बुद्धि-हीन; *See* (*s.*). 2 निरर्थक, अविमृश्यकृत-दृत्त. **-ishly**, *adv.* मूढतया, अज्ञानेन, मूर्खवत्, मूढवत् मौर्ख्येण. **-ishness, -Folly,** *s.* मौर्ख्यं, आडयं, मोहः, मंदमतिता, मूर्खता, मूढता, बालिश्यं, बालिशता, दुर्बुद्धिता, अज्ञानं, निर्बुद्धित्वं, ज्ञानाभावः, अनात्मज्ञत्वं.

Foot, *s.* पादः, पदं, चरणः-णं, अंघ्रिः. 2 तलं, अधोभागः, मूलं; उपस्थः. 3 (In metre) चरणः, पदं. 4 पत्ति-पदाति-समूहः-गणः. —*v. t.* पादेन प्रहृ 1 P or तड् 10 or आहन् 2 U; 'f. of a mountain' उपत्यका, पादः; 'set one's f. in' पदं कृ 8 U (lit. and fig.); आश्रमे पदं करिष्यसि (S. 4), कुतूहलेन प्रश्नाश्रया हृदि पदं कृतं (Ka. 133); 'walk on f.' पद्भ्यां चर्-व्रज् 1 P, पादचारी भू; 'walking on f.' पादगः, पादचारः; पदातिः; 'water for the feet' पाद्यं; पादोदकं; 'set on f.' प्रवृत् c., उपक्रम् 1 A; प्रारभ् 1 A; 'f.-board' चरणफलकः, 'f.-boy' चेटः, भृत्यः, बालसेवकः, युवप्रेष्यः; 'f.-bridge' संक्रमः, संक्रमसेतुः; 'f.-fall' चरणपातः, पादन्यासः, स्खलनं; 'f.-fight' पदातिपादग-युद्धं; 'f.-licker' पीठमर्दः, चरणसेवक, 'f.-man' चेटः, सेवकः, प्रेष्यः, परिचरः, किंकरः, 'f.-mark-print' पाद-पद-चिह्नं, पदपंक्ति *f.*, पदवी, पद्धति *f.*, पादमुद्रा; f.-pace' पादन्यासः, चरणक्रमः-पातः; 'f-path' संसरणं, चरणवीथि *f.*, पथिकमार्गः, पद्या, 'f.-soldier' पदातिः, पत्तिः, पादातिः-तिकः, प(पा)दातः, पादचारः, प(पा)दगः, पदाजिः, पद्गः, पदिकः; 'f.-step' पादन्यासः, पद-चरण-निक्षेपः-पातः, पदं, पदपंक्ति *f.* (f.-print); पद्धतिः, मार्गः, वर्त्मन् *n.*, पदवि-वी *f.*, लक्षणं; 'f.-stool' पाद-पीठं, चरणपीठं, पादासनं. **-ing**, *s.* पदं, स्थानं, भूमि *f.*, स्थलं, आस्पदं, पदवि-वी, सरणि *f.* 2 वास्तु *m.*, *n.*, मूल, उपष्टंभः. 3 आश्रयः, अवलंबनं, आधारः. 4 स्थिति *f.*, वृत्ति *f.*, अवस्था, भावः, दशा; 'f. of equality' समता, तुल्यभावः. **-less**, *a.* पादहीन, अचरण.

Fop, *s.* दर्शनीयमानिन् *m.*, वेषाभिमानिन् *m.*, दंभिन् *m.*, सुवेशमानिन् *m.* छेकः, रूपगर्वितः. **-pish**, *a.* दंभिन्.

For, *prep.* (On account of) ex. by instr. or abl.; अर्थे-र्थं, हेतुना, हेतोः, कृते, कारणात्, निमित्तात्, निमित्तं, in comp.; 'for his deliverance' मोक्षनिमित्तं, मुक्तिहेतोः, &c. 2 (Purpose) by dat. or by अर्थं-अर्थे in comp. 3 (For the sake of) अर्थे, कृते (with gen.) or by dat. 4 (In exchange for) प्रति, स्थाने, विनिमयेन; तिलेभ्यः प्रतियच्छति माषान्, or तिलविनिमयेन &c. 5 (Considering) अपेक्ष्य, प्रतीक्ष्य, आलोच्य, इति कृत्वा, अपेक्षया in comp. 6 (Towards) प्रति, उद्दिश्य, (with acc.); संमुखं, अभिमुखं, in comp. 7 (Regarding) तावत्, उद्दिश्य; कृते; 'f. myself, rest secure' मद्विषये तावद्वीतचिंतो भव, मामुद्दिश्य न चिंता कार्या. 8 (Showing price) by instr.; त्रिरूपकेण क्रीतः 'bought f. 3 Rs.' 9 (Duration) by acc.; 'for 10 days' दशादिवसं; 'f. how many years' कियंति वर्षाणि; oft. by यावत् or पर्यंतं, आ with abl.; 'f. life' यावज्जीवं, आजीवितांतात्. 10 (on the side of) पक्षे; 'they are f. war' विग्रहमनुमोदंते, विग्रहमुपदिशंति. 11 (As if) वत् or इव. 12 (According to) यथा, अनुरूपं, अनुसारेण, in comp.; 'f. all' ex. by अनादृत्य (with acc.) or loc. abs. 'f. all his wealth' विद्यमानेपि महाकोशे, महाकोशमनादृत्य; 'f. a long time' चिरं, चिरकालं, चिराय; 'out of love f. me' मद्गतप्रीत्या; 'f. the most part' भूयिष्ठ in comp., प्रायः, प्रायेण; 'f once' सकृदेव. —*conj.* हि (not at beginning of assertions); यतः, यस्मात्कारणात्, यत्, यस्मात्, इति हेतोः, अनेन हेतुना.

Forage, *s.* यवसं, घासः, तृणादि. 2 पाथेयं, भोजनसंभारः, खाद्यसामग्री. 3 खाद्यान्वेषणं, खाद्यार्थं परिभ्रमणं; प्रसरणं. —*v. i.* बलात् खाद्यद्रव्यं आ-हृ 1 P, भोजनार्थं परिभ्रम् 1, 4 P. **-ing**, *s.* भोजनान्वेषणार्थं परिभ्रमणं-प्रसरणं.

Foray, *s.* उपद्रवः, अवस्कंदः, विप्लवः.

Forbear, *v.* विरम् 1 P; निवृत् 1 A, (with abl.). परिहृ 1 P, वृज् 10. त्यज् 1 P. 2 विलंब् 1 A. 3 सह् 1 A, क्षम् 1 A, मृष् 4 P, 10, तिज् desid. (तितिक्षते). 4 सं-नि-यम् 1 P, निग्रह् 9 P, आ-वृ 5 U; निरुध् 7 U; 'he could not f. expressing his joy, or laughter' संतोषं-हासं-निग्रहीतुं न पारयामास. **-ance**, *s.* क्षमा, तितिक्षा, क्षांति *f.*, सहनं, सहिष्णुता, मर्षणं, सहनशीलता. 2 निवृत्ति *f.*, विरामः, विरति *f.*, वर्जनं, त्यागः, परिहारः. 3 संयमः, दमः, यमः, निग्रहः. **-ing**, *s.* तितिक्षु, सहिष्णु, सहनशील, क्षमिन्, सहन, क्षंतृ, क्षमितृ.

Forbid, *v. t.* प्रति-नि षिध् 1 P or c., प्रत्या-ख्या 2 P, प्रत्यादिश् 6 P, निरा-अपा-कृ 8 U. 2 निरुध् 7 U, नि-वृ c. or वार् 10; 'God f.' शांतं पापं or (इति) शांतं, प्रतिहतममंगलं. **-ding, -dance,** *s.* नि-प्रतिषेधः, प्रत्याख्यानं, प्रत्यादेशः. 2 निवारणं, निरोधः. **-ding**, *a.* घृणावह, बीभत्सजनक, अप्रिय.

Force, *s.* बलं, शक्ति *f.*, सामर्थ्यं (fig. also); 'the f. of this word' अस्य शब्दस्य शक्तिः &c. 2 प्रभावः, वीर्यं, शौर्यं, वि-परा-क्रमः, ऊर्जस् *n.*, प्रतापः, प्राबल्यं, गौरवं. 3 बलात्कारः, प्रसभः, साहसं, बलं, प्रमाथः, आवेशः; f. of passion' रागावेशः. 4 अभिघातः, आपातः, अभिभवः. 5 सिद्धि *f.*, फलं, निष्पत्ति *f.*; 'put or bring into f.' प्रवृत् c. 6 सैन्यं, बलं, सेना, अनीकः-कं, पृतना, अनीकिनी, चमूः, वाहिनी, ध्वजिनी, चक्रं, वरूथिनी. —*v. t.* Ex. by causal of verbs, with बलात् or बलेन, or प्रवृत् c.; *See* **Compel;** 'he was f. ed to admit that &c.' इति अभ्युपगमनं अवश्यकं मेन. 2 भिद् c., प्रणुद् 6 P, समाकृष् 1 P, प्रणुद् 10, प्रोत्सह् c., 3 धृष् c., बलात् अभिगम् 1 P, बलात्कारं कृ 8 U; 'f. an entrance' बलेन प्रविश् 6 P; 'f. a town' पुरं लंघ् 1 A, 10 or भंज् 7 P or बलात् प्रविश्. —**ed,** *a.* यत्नकृत, यत्नपूर्व, असहज, कृत्रिम, क्लिष्ट (as meaning). —**Forcible,** *a.* प्रबल, समर्थ, क्षम, शक्तिमत्, बलवत्, सप्रभाव, अमोघ, अनिष्फल, प्रभविष्णु. 2 गौरवेण उक्त or प्रतिपादित, दृढ, तीक्ष्ण. 3 बलेन कृत, बलात्कृत, साहसिक (की *f.*), बल in comp.; 'f. consent' बलाद्नुमोदनं. —**Forcibly,** *adv.* (by force) बलेन, बलात्, प्रसभं, प्रसह्य, बलात्कारेण, हठात्. 2 सगौरवं, दृढतया.

Force-meat, *s.* मिश्रान्नं, उपस्कारः, व्यंजनं.

Forceps, *s.* संदंशकः-शिका.

Ford, *s.* तीर्थं, तरणस्थानं-स्थलं, घट्टः. —*v. t.* पद्भ्यां तॄ 1 P or पारं गम् 1 P. —**able,** *a.* अल्पजल, सुतर, सुप्रतर; 'the rivers having become f.' सुखोत्तारतामापन्नास्वापगासु (Ka. 326).

Fore, *a.* अग्र, पूर्व, अग्रगामिन्; gen. ex. by अग्र, पूर्व in comp.; 'f.-fathers' पूर्वजाः, पितरः, पूर्वे-पूर्वाः, वृद्धाः; 'f.-finger' प्रदेशिनी, तर्जनी; 'f.-foot' अग्रपादः; 'f.-head' ललाटं, भालं, ललाट-भाल-पट्टं, अलि(ली)कं, गोधिः; 'f.-land' अंतरीपः-पं, उदग्रभूः-भूमिः; 'fore leg' *s.* पूर्व-अग्र-पादः; 'f.-lock' ललाटकेशाः-कचः; 'f.-man' अध्यक्षः, अधिष्ठातृ *m.*, अधीशः; 'f.-mentioned-named-said-spoken' प्रागुक्त, पूर्वोक्त, पूर्वकथित; 'f. mast' अग्रकूपकः; f.-most' प्रधान, उत्कृष्ट, परम; 'f.-noon' पूर्वाह्णः-कालः; 'f.-part' अग्रभागः, पूर्व-आदि-प्रथम-भागः; 'f.-rank' अग्र-प्रधान-पर्व; 'f.-tooth' अग्रदंतः, राजदंतः, 'f.-ward' सेनामुखं, रणशिरस् *n.*; 'foreward', *s.* *See* **Preface.**

Forearm, *s.* प्रकोष्ठः, अग्रभुजः-हस्तः-बाहुः. —*v. t.* पूर्वं सन्नह् 4 P or c. or सज्जीकृ 8 U.

Forebode, *v. t.* आ-,सूच् 10, माङ्गल्य-अमंगलं सूच् c., पूर्वं कथ् 10; (अनिष्टं) पूर्वं ज्ञा 9 U or अव-गम् 1 P, अनु-मा 3 A; *See* **Bode;** 'the tawny lightning f. s a hurricane' वाताय कपिला विद्युत् (S. K.). —**er,** *s.* अनिष्टावेदकः, अनिष्टसूचकः. —**ing,** *s.* अनिष्टसूचनं-ज्ञानं-दर्शनं.

Forecast, *v. t.* पूर्व-अग्रे चिंत् 10 or निरूप् 10 or निर्दिश् 6 P or अनुसं-धा 3 U. —*s.* पूर्वकल्पना-विवेकः, अग्रनिरूपणं, पूर्वचिंतनं, दीर्घदृष्टि *f.*

Foreclose, *v. t.* प्रतिबंध् 9 P, प्रति-नि-षिध् 1 P. —**ure,** *s.* प्रतिबंधः, प्रतिषेधः.

Fore-determine, *v. t.* अग्रे-पूर्वं-निर्णी 1 P or निश्चि 5 U.

Foredoom, *v. t.* पूर्वं निर्दिश् 6 P or वि-धा c.

Fore-fend, *See* **Forbid.**

Forego, *v. t.* त्यज् 1 P, हा 3 P, उत्-वि-सृज् 6 P; 'I shall f. my name' स्वनामत्यागं करोमि (P. 1); 'a foregone conclusion' पूर्वनिर्णीतः-प्रागेवसिद्धः-सिद्धांतः.

Foreign, *a.* विदेशीय, वैदेशिक-पारदेशिक (की *f.*), विदेशज, विदेशिन, अन्य-विदेश-देशज-देशीय-देशोद्भव, पारदेश्य, विदेशागत, बहिर्देशोद्भव; 'a f. country' विदेशः, परदेशः, देशांतरं. 2 बाह्य, बहिर्भव, अप्रस्तुत, अप्रकृत; 'this is f. to our present inquiry' अप्रकृतमेतदस्मिन् विषये. —**er,** *s.* वैदेशिकः, पारदेशिकः, अन्यदेशीयः-देशजः; *See* (*a.*). —**ness,** *s.* बाह्यता, भिन्नता; अप्रकृतता, असंबंधः.

Fore-imagine, *v. t.* पूर्व-अग्रे-चिंत् 10 or मन् 4 A.

Fore-judge, *v. t.* पूर्वं अवेक्ष् 1 A, निश्चि c or निर्णी 1 P.

Fore-know, *v. t.* पूर्वं ज्ञा 9 U or बुध् 1 P or विद् 2 P; Know, q. v., प्रबुध् 1 P, अग्रे निरूप् 10. —**ledge,** *s.* अग्र-पूर्व ज्ञानं, भविष्यज्ज्ञानं, अग्रनिरूपणं, अग्र-पूर्व-दृष्टि.

Forensic, *a.* व्यावहारिक (की *f.*) व्यवहारानुबद्ध.

Fore ordain, *v. t.* अग्रे-पूर्वं-निर्दिश् 6 P. or नियुज् 7 A, 10 or वि-धा 3 U.

Forerun, *v. i.* पूर्व-पुरः-अग्रे-सृ or धाव् or गम् 1 P or वृत् 1 A or या-इ 2 P. —**ner,** *s.* अग्रेसरः, पुरो-गः-गामिन् *m.*, अग्र-गः-गामिन् *m.*, अग्रवर्तिन् *m.*, अग्रगतः, पूर्वसूचक.

Fore-say,-speak, प्राक्-पूर्वं-वद् 1 P, or कथ् 10.

Foresee, *v. t.* पूर्वं-दृश् 1 P or ज्ञा 9 U भावि-अनागतं-दृश् or अवेक्ष् 1 A, अग्रे नि-रूप् 10; gen. ex. by भाविन्; 'I f. my ruin' जानामि भाविनं नाशं. —**Foresight** *s.* दूरदर्शित्वं-ता, दूरदृष्टि-दीर्घदृष्टि *f.* अग्रनिरूपणं, दूरदर्शनं.

Foreshow, *See* **Forebode.**

Forest, *s.* वन, अरण्यं, काननं, विपिनं, अट-वि-वी *f.*, गहनं, कांतारः-रं; 'a large f.' अरण्यानी; 'growing in f.' वन्य, आरण्य,-क, वनोद्भव, अरण्यज-जात, वन or अरण्य in comp. **-er,** *s.* वनेचरः, वनवासिन् *m.*, आरण्यकः, आटविकः, वनस्थः, वनचारिन् *m.*, वनचरः-वर्तिन् *m.*, वनौकस् *m.*, अरण्यसद् *m.*. 2 अरण्यरक्षकः, वनपालकः.

Forestall, *v. t.* पूर्वं ग्रह् 9 P or आदा 3 A, पूर्वग्रहणेन मोघीकृ 8 U; *See* **Anticipate.** 2 पूर्वं क्री 9 U.

Foretaste, *v. t.* पूर्वं अनुभू 1 P or आस्वाद् 1 A or भुज् 7 A. **-s.** पूर्वानुभवः, पूर्व-अग्र-ज्ञानं, पूर्वास्वादः, पूर्व-अग्र-भुक्ति *f.*

Foretell, *v. t.* पूर्वं कथ् 10, भावि-भविष्यद् वद् 1 P or वच् 2 P; प्रदृश् c., अनागतं निविद् c.; *See* **Predict.** **-er,** *s.* भविष्यद्वादिन् *m.*, भाविदर्शकः, अनागतनिवेदकः, दैवज्ञः.

Forethink, *v. t.* पूर्वं चिंत् 10 or विमृश् 6 P. **-Forethought,** *s.* अग्र-पूर्व-चिंता, पूर्वविमर्शः-विवेकः, प्रसमीक्षा-क्षणं, दूर-दीर्घ-दृष्टि *f.*, पूर्वविचारणं-णा.

Foretoken, *v. t.* पूर्वं सूच् 10. **-s.** पूर्वलक्षणं-चिह्नं-लिंगं, भाविलक्षण

Forewarn, *v. t.* पूर्वं सूच् 10 or प्रबुध् c., अग्रे उपादिश् 6 P or ज्ञा c. (ज्ञापयति); 'to be f. ed is to be fore-armed' पूर्वप्रबोधनं पूर्वसन्नाहतुल्यं. **-ing,** *s.* पूर्वप्रबोधः-धनं. पूर्वोपदेशः.

Forfeit, *v. t.* दंड् pass., भ्रंश् 1 A. 4 P, च्यु 1 A, परि-हा pass., (with abl.); 'f. s his kingdom' राज्यात्परिभ्रंशते; 'f. s his right' स्वत्वं तस्मान्निवर्तते; oft. ex. by हीन-हृत in comp.; 'you will f. all your wealth' हृतसर्वस्वो भवेः, सर्वस्वं दण्ड्यथाः. **-s.** दंडः, धन-अर्थ-दंडः. **-ed,** *a.* दंडित, भ्रष्ट, च्युत, हीन; 'who has f. ed his right' स्वत्वभ्रष्टः, च्युताधिकारः; हृतसर्वस्वः, &c. **-ure,** *s.* हानि *f.*, च्युति *f.*, भ्रंशः, अपहारः, अपवर्तनं, नाशः, दंडदानं.

Forge, *v. t.* घट् c. (घटयति), रच् 10, निर्मा 3 A, वि-धा 3 U, कृप् c. 2 मिथ्या-कूटं-कृ 8 U, कपटकूट in comp.; 'f. s a letter' कूट-कपट-लेखं प्रयुंक्ते; *See* **Counterfeit.** **-s** निर्माणस्थानं; अग्निकुंडं, उष्मानं. **-er,** *s.* कूट-कारः-कृत् *m.*, कपटलेखकारिन् *m.* **-ry,** *s.* कूट-कपट-लेखकरणं, कूट-कपट-करणं, कूटरचना. **-ing,** *s.* घटना. घटनं, रचना-नं; कूटनिर्माण, &c.

Forget, *v. t.* विस्मृ 1 P, न स्मृ; स्मृतेः-स्मरणाद्भ्रंश् 1 A, 4 P or अप-इ 2 P, (of what is forgotten). **-ful,** *a.* विस्मरणशील. लुप्त-नष्ट-स्मृति; अनवहित, प्रमत्त **-fulness,** *s.* विस्मृति *f.*, विस्मरणं, स्मृतिलोपः, स्मृतिनाशः-भ्रंशः-हानि *f.*, विस्मरणशीलता, अनवधानं.

Forgive, *v. t.* क्षम् 1 A, (with acc. of person also), मृष् 4 P, 10, सह् 1 A, तिज् desid. (तितिक्षते). (with acc. of fault). 2 मुच् 6 P, अव-सृज् 6 P, त्यज् 1 P, (as a debt). **-ness,** *s.* क्षमा, तितिक्षा, क्षांति *f.*, सहिष्णुता, मर्षणं; 'f. of sin' पाप-दोष-मुक्ति *f.* -मार्जनं. **-ing,** *a.* क्षमिन्, सहिष्णु, क्षमावत्, क्षमाशील, तितिक्षु, क्षमायुक्त, क्षंतृ, क्षमितृ.

Fork, *s.* कंटकः, शूलं. **-v. i.** विभिद् pass., द्विशिखीभू 1 P, द्विधा भिद् pass. **-ed, -y,** *a.* द्विशिख, द्व्यग्र; 'having a f. tongue' द्विजिह्व; 'f. lightning' विद्युल्लता.

Forlorn, *a.* त्यक्त, दीन, विधुर, अनाथ, अनाश्रय, गति-शरण-हीन, अ-निः-शरण, अ-निः-सहाय, निरवलंब, निराधार, निराश्रय, अगतिक.

Form, *s.* रूपं, आकारः, आकृति *f.*; संस्थानं; वपुस् *n.*, मूर्ति *f.*, (**Body,** q. v.) 2 तंत्रं, मार्गः, पद्धति *f.*, प्रकारः, रीति *f.*, विधा-धः, विधिः, भेदः; 'f. of government' राज्यतंत्रं-पद्धतिः. 3 विधिः, नियमः, स्थिति *f.*, व्यवस्था, आचारः, क्रमः, मर्यादा, व्यवहारः, संस्कारः; 'in due f.' यथाविधि, विध्यनुसारेण, विधिवत्. 4 रचना-नं, विन्यासः. 5 सहाध्यायिवर्गः, छात्रपंक्ति *f.*, गणः. 6 दीर्घपीठं-आसनं. **-v. t.** निर्मा 2 P, 3 A, रच् 10, कृ 8 U, वि-धा 3 U, उत्पद् c., घट् c. (घटयति), क्लृप् c.; 'f. plans' उपायान् चिंत् 10 or मनसा क्लृप् c.; 'the cords that f. ed the net' याभिः रज्जुभिर्जालं निर्मितं. **-al,** *a.* अत्याचारसेविन्, नियमनिष्ठ, अत्यादरयुक्त, सभ्याचारविशिष्ट. 2 नैयमिक-वैधिक (-की *f.*), नियमानुसारिन्, व्यवहारानुरूप, आचारानुगत, आचारानुसारिन्, विध्यनुरूप; आचार in comp.; 'just perform the f. salutation' आचार मात्रं प्रतिपद्यस्व. 3 यथार्थ, विशिष्ट. **-alist,** *s.* नियममात्रसेविन् *m.* **-ality,** *s.* आचारः, उपचारः, यथाविधि वर्तनं; अत्यादरः; 'a title of f.' उपचारपदं; 'enough of f.' अलमत्यादरेण. **-ally,** *adv.* सोपचारं, अत्यादरेण, सभ्याचारपूर्वं, अत्यादरपूर्वं. 2 यथाविधि, विधिवत्, नियमानुसारेण. **-ation,** *s.* घटना-नं, निर्माणं, विधानं, रचना, कल्पना-नं, उत्पादनं, उद्भवः; सृष्टि *f.* **-ed,** *a.* घटित, निर्मित, कृत, रचित, क्लृप्त, मय in comp.; 'f. of gold' हेमघटित, सुवर्णमय, &c.; *See* **Composed.** 2 रूप-आकार-आकृति in comp.; 'f. like a conch' शंखाकृति; 'well-f.' सुरूप **-less,** *a.* निराकार, अरूप.

Former, *a.* पूर्व, प्रथम, अग्रिम, आद्य, आदिम, पूर्वकालीन, प्राक्कालीन, प्राचीन, गतकालीन, पुराण, पुरातन. **-ly,** *adv.* प्राक्, प्राक्काले, भूत-गत-काले, पुरा, पूर्वं, पुराकल्पे, पूर्वकाले; 'as f.' यथापूर्वं, पूर्ववत्; 'f. stated' प्रागुक्त, पूर्वोक्त; 'f. heard' श्रुतपूर्व.

Formic, *a.* पिपीलिका-पुत्तिका-संबंधिन्.

Formidable, *a.* दारुण, भयावह, भीषण, भयानक, भयजनक, भयप्रद, भैरव (वी *f.*), घोर, उग्र, प्रतिभय, रौद्र (द्री *f.*). **2** (Great) प्रबल, महत्, अतिघोर. **-ness,** *a.* भयानकत्वं, भीषणता, भैरवं.

Formula, *s.* सूत्रं, विधिः, नियमः, व्यवस्था, स्थिति *f.* **-Formulate,** *v. t.* विधि-सूत्र-रूपेण रच् 10, or व्यव-स्था c. (स्थापयति).

Fornicate, *v. i.* व्यभि-चर् 1 P, वेश्यां सेव् 1 A or अभिगम् 1 P. **-ion,** *s.* व्यभिचारः, जारकर्मन् *n.*, वेश्यागमनं-सेवा, वेश्याप्रसंगः. **-or,** *s.* व्यभिचारिन् *m.*, जारः. **-Fornicatress,** *s.* **Harlot,** q. v.

Forsake, *v. t.* त्यज् 1 P, हा 3 P, उत-वि-अप-सृज् 6 P, उज्झ् 6 P, रह् 10 (रहयति). **-er,** *s.* त्यागिन् *m.*, त्यक्त *m.* **-ing,** *s.* त्यागः, उत्सर्गः.

Forsooth, *adv.* नूनं, नाम, किल, खलु, यत्सत्यं, सत्यमेव.

Forswear, *v. t.* सशपथं त्यज् 1 P or प्रत्या-ख्या 2 P or अप-नि-ह्नु 2 A. **-v. i.** मिथ्या-शप् 1 U, कूट-मिथ्या-शप्. **-er,** *s.* असत्यशपथः, मिथ्याशपथकारिन् *m.*

Fort, Fortress, *s.* दुर्गं, कोट्टः, कोट्टि *f.*; 'governor of a f.' दुर्गाध्यक्षः, कोट्टपालः.

Forte, *s.* विशिष्ट-श्रेष्ठ-गुणः, प्रधानगुणः.

Forth, *adv.* बहिः, अग्रे, पुरतः; with verbs, ex. by निर्, उत्, प्र pr. **2** प्रभृति, आरभ्य; 'from this time f.' अद्य-अतः-प्रभृति, अद्यारभ्य; 'f.-coming' आगामिन्, आसन्न. उपस्थित. **-Forthwith,** *adv.* सपदि, झटिति, द्रागेव, सद्यः, अचिरात-रेण, आशु, अविलंबितं, तत्क्षणात्.

Fortify, *v. t.* दृढीकृ, स्थिरीकृ 8 U, दृढयति (D.), सं-स्तंभ् 9 P or c. **2** सुगुप्त-सुरक्षित-*a.* कृ, परिखया आ-परि-वृ 5U or परिवेष्ट् c. **-ication,** *s.* गुप्ति *f.*, परिखा, प्राचीरं, दुर्ग, कूटः, कोट्टः, प्राकारपरिखादि.

Fortitude, *s.* धैर्यं, सत्त्वं, धीरता, मनःस्थैर्यं. **2** वीर्यं, शौर्यं, विक्रमः, साहसं, पराक्रमः.

Fortnight, *s.* पक्षः, मासार्धं, अर्धमासः.

Fortuity, *s.* दैवयोगः-घटना, दैवं, समापत्ति *f.* **-ous,** *a.* दैवायत्त, दैवाधीन, अचिंतित, अतर्कितोपनत, आकस्मिक (की *f.*). **-ously,** *adv.* **Accidentally,** q. v.

Fortune, *s.* दैवं, भाग्यं, भागधेयं, विधिः, अदृष्टं, भवितव्यता; *See* **Fate. 2** ऋद्धि *f.*, श्री, लक्ष्मीः, ऐश्वर्यं, संपद् *f.*, संपत्ति *f.*, धनं. **3** शुभं, कल्याणं, भद्रं, शिवं, सौभाग्यं, मंगलं, पुण्योदयः; 'bad f.' दुर्दैवं, दुर्-मंद-भाग्यं, दैवदुर्विपाकः; 'tell f.' शुभाशुभं कथ् 10 or चिंत् 10 or निरूप् 10 or आलोच् 10; 'f.-teller' दैवज्ञः, गणकः, कार्तांतिकः, दैवचिंतकः; 'a female f.-teller' विप्रश्निका, ईक्षणिका, दैवज्ञा; 'f.-telling' शुभाशुभदर्शनं. **-ate,** *a.* भाग्यवत्, महाभाग, सुभाग्य, सुभग, सौभाग्यवत्, दैवशालिन्, धन्य, पुण्यवत्, कृतिन्, श्रीमत्, पुण्यभाज्. **3** शुभ, कल्याण, शिव, मंगल, भद्र. **-ately,** *adv.* दैवात्, दैवयोगात्, दिष्ट्या, सौभाग्येन, भाग्यदैव-वशात्.

Forty, *a.* चत्वारिंशत् *f.* **-Fortieth,** *a.* चत्वारिंश (शी *f.*)-शत्तम (मी *f.*).

Forward, *a.* अग्रिम, आदिम, अग्रस्थ, पुरोगामिन्. **2** अपूर्वकाल, आकालिक (की *f.*). **3** धृष्ट, प्रगल्भ, निर्लज्ज, प्रतिभानवत्, सप्रतिभ, अविनीत. **4** उद्यत, व्यग्र, उद्युक्त, प्रत्युत्पन्न, अविलंबित. **-v. t.** सं-प्र-वृ c., उपकृ 8 U, पुरस्कृ, प्र-वृत् c., समुत्सुज् 10, साहाय्यं कृ, उन्नतिं नी 1 P, अनुग्रह् 9 P. **2** प्रेष् c., प्र-चुद् 10, प्र-हि 5 P. **3** **Accelerate,** q. v. **-adv.** (f. s) अग्रतः, पुरतः; पुरः, अग्रे, पुरस्तात्, सं-अभि-मुखं; 'this day f.' अद्य प्रभृति; 'to go backward and f.' गतागतं कृ; *See* **Forth. -ness,** *s.* उत्साहः, अविलंबः, उद्योगः. **2** प्रागल्भ्यं, निर्लज्जता, धाष्ट्यं, अतिप्रसंगः, अविनयः, प्रतिभानं.

Fosse, *s.* खातं, परिखा.

Fossick, *v. t.* लाभाय, अन्विष् 1 P.

Fossil, *a.* शिलाजात. **-s.** धातुः; शिलाभवं, धातुद्रव्यं; उत्खातद्रव्यं. **-ist,** *s.* धातुविद्याज्ञः

Foster, *v. t.* पुष् 1, 9 P; पा c. (पालयति), प्र-सं-वृध् c., भृ 3 U, लल् 10. **2** (Love, hatred, &c.) धृ 10, वह् 1 P, वृध् 9 P; 'f.-brother' धात्रेयः, धात्रीपुत्रः; 'f.-child' पोष्यपुत्रः (त्री *f.*), पराचितः; परिस्कं(ष्कं)दः, परिस्क(ष्क)न्नः; परजातः, परैधितः; 'f. father' पालकपितृ *m.*, प्रतिपालकः, धर्मतातः; 'f.-mother' धात्री, उपमातृ *f.*, प्रतिपालिका; अंकपालिका, मातृका, धात्रेयी.

Foul, *a.* मलिन, समल, अशुचि, कलुष, मलदूषित, मलीमस, आविल, अशुद्ध, अपवित्र, अमेध्य, पंकिल. **2** कुत्सित, कश्मल, गर्ह्य, निंद्य, दुष्ट. **3** अवाच्य, अशिष्ट, अश्लील (language). **4** कूट, कपट, पाप, in comp.; 'f. means' कपटप्रबंधः; 'even by f. means' दुरितैरपि (R. viii. 2); 'f. play' दुरितं. पापं; 'f. weather' दुर्दिनं; 'f. quality' रजोगुणः; 'f. smell' पूतिगंधः, दुर्गंधः; 'fall f. of' उपरि पत् 1 P, परस्परं आ-हन् 2 P or संघट्ट् 1 A. 'f.-mouthed' दुर्मुख, वाग्दुष्ट, कटुवाच, मुखर, परिवादिन्. **-v. t.** मलिनयति-कलुषयति-आ

चिलयति (D.); मुष् c. (मूषयति.) -ly, *adv.* अतिशुद्धं, घोरं, मलिनं. -ness, *s.* मालिन्यं, मलिनता, &c.

Found, *v. t.* स्था c.(स्थापयति), प्रति-सं-अव-रुह् c. (रोपयति), निर्मा 3 A or c. (मापयति), बंध् 9 P, प्रवृत् c., आरभ् 1 A; मूल, निबंधन, निष्ठ, in comp.; 'attachment f. ed on love' प्रेममूला-भावनिबंधना-रतिः; 'f. ed on ignorance' अज्ञानज, अज्ञान-मूल-लक, अविद्याकल्पित. -ation, *s.* प्रतिष्ठापनं, संस्थापनं; निर्माणं. 2 वास्तु *m.*, *n.*, पोटः, गृहप्रतिष्ठा, गृहमूलं, भित्तिमूलं, वेश्मभूः. 3 (Fig.) मूलं, आधारः, उपष्टंभः. -er, *s.* संस्थापकः, प्रवर्तकः, आरंभकः, आविष्कर्तृ *m.*, प्रतिष्ठापकः, कर्तृ *m.* प्रयोजकः. -v. *i.* जलमज्जनेन नश् 4 P, जले मस्ज् 6 P. -ling, *s.* अपविद्धबालकः, उत्सृष्टापत्यं.

Foundery, *s.* संधानी, कुप्यशाला.

Fount, Fountain, *s.* निर्झरः, उत्सः, प्रस्रवणं, वारिप्रवाहः. 2 मूलं, योनि *f.*, प्रभवः, हेतुः, आदिहेतुः. 3 धारायंत्रं (artificial f.).

Four, *a.* चतुर्, चतुष्टय; 'f. times' चतुः; 'in f. ways' चतुर्धा; 'f.-cornered' चतुरस्र-श्र; 'f.-fold' चतुर्गुण; 'f.-footed' चतुष्पाद्, चतुष्पाद्; 'f. score' अशीति *f.* -Fourth, *a.* चतुर्थ (र्थी *f.*), तुर्य, तुरीय. -*s.* चतुर्थभागः, पादः, चतुर्थांशः; तुरीयः, तुर्यः, तुर्यांशः; 'a rupee and one f.' सपादरूपकः. -ly, *adv.* चतुर्थस्थाने. -Fourteen, *a.* चतुर्दशन्. -th, *a.* चतुर्दश (शी *f.*).

Fowl, *s.* खगः, पक्षिन् *m.*, शकुनः; *See* **Bird.** 2 कुक्कुटः, ताम्रचूडः, चरणायुधः. -*v. i.* पक्षिणो ग्रह् or बंध् 9 P or धृ 1 P. -er, *s.* शाकुनिकः, व्याधः. शकुनिलुब्धः, जालिकः, लुब्धकः, पक्षिग्राहकः, जीवांतकः. -ing, *s.* पक्षिग्रहणं-वधः-घातः.

Fox, *s.* शृगालः, कि(खि)खिः, खिंकिरः, भूरिमायः, गोमायुः; *See* **Jackal;** 'f.-hunt' शृगालानुसरणं; 'f.-like' विदग्ध, धूर्त, बहुमाय.

Fracas, *s* कलहः.

Fraction, *s* भेदः, भागः, अपूर्णांकः, राशिभागः. -al, *a.* अपूर्ण, भागिक (की *f.*), भागिन्.

Fractious, *a.* कलहकारिन्, शीघ्रकोप; वामशील.

Fracture, *s.* भंगः, भेदः, विदारणं, स्फोटनं, विभंगः, विभेदः. -*v. t.* भंज् 7 P, भिद् 7 P भिद् 10; *See* **Break.**

Fragile, *a.* भंगुर, भंगशील, भिदुर, विदलिम, सुखभेद्य, सुभंग; विनश्वर, क्षयिन्. -ity, *s.* भंगुरता, क्षयिता, भिदुरता.

Fragment, *s.* खंडः-डं, शकलः-लं, भागः, अंशः, दलं, भिन्नं; 'in a thousand f. s' सहस्रधा. -ary, *a.* अपूर्ण, भागिक, खंडयुक्त.

Fragrant, *a.* सुरभि, सुगंधि, सुवास, आमोद-परिमल-वत्, सुवासित, सामोद, परिमलोद्गारिन्, गंधयुक्त, गंधवत्; तिक्त, कषाय. -ly, *adv.* सवासं, सामोदं, सुगंधं. -Fragrance, *s.* आमोदः, परिमलः, सौरभं, सौरभ्यं; गंधः, वासः, सुवासः, सुगंधः.

Frail, *a.* भंगुर, नश्वर, ध्वंसिन्, अनित्य, अस्थायिन्, क्षयिन्, सद्यःपातिन्, क्षण-भंगुर-विध्वंसिन्. -ness,-ty, *s.* भंगुरता, नश्वरत्वं, क्षयिता, &c. 2 दोषः, स्खलितं, प्रमादः.

Frame, *v. t.* वि-,रच् 10, वि-धा 3 U, क्लृप् c., कृ 8 U, घट् c. (घटयति), संवि-धा, समा-धा, निर्मा 2 P, 3 A. 2 निर्बंध् 9 P. 3 सहृशीकृ; 'f. in the mind' मनसा चिंत् 10 or कल्पृ c., चित्ते कृ. -*s.* निर्माणं, रचनं-ना. घटनं-ना. 2 आधारः, उपष्टंभः; आवरणं, कोशः, आवेष्टनं. 3 शरीरं, देहः, गात्रं, वपुस् *n.*, कायः, अंगं; 'f. of body' देहबंधः; 'of a hardy f.' वज्रदेहिन्, सिंहसंहनन. 4 भावः, वृत्ति *f.*, स्थिति *f.*, दशा, अवस्था; 'joyous f. of mind' आनंदवृत्तिः. 5 आकारः, रूपं, आकृति *f.*, रीति *f.*, संस्थानं.

Franchise, *s.* पौरजनाधिकारः. 2 मुक्ति *f.*, मोचनं, स्वाधीनता. -*v. t.* मुच् 6 P.

Frangible, *See* **Fragile.**

Frank, *a.* निष्कपट, सरल, ऋजुमति-बुद्धि, उदार, निर्व्याज, स्पष्ट-स्फुट-वादिन्, असंवृत, अवक्र, अमाय, निर्व्यलीक, दक्षिण, अगूढभाव; अकपट, अव्याज, अनायिन्; 'f.-hearted' विमलात्मन्, उदारधी; शुद्धांतःकरण. -ly, *adv.* निर्व्याजं, निष्कपटं, अमायया, सरलं. -ness, *s.* अमाया, ऋजुता, निष्कापट्यं, औदार्यं, दाक्षिण्यं, सारल्यं, अकापट्यं, &c.

Frank-incense, *s.* कुंदुरः-रुः, कुंदुः-दुः, मुकुंदः, पालंकी.

Frantic, *a.* उन्मत्त, मदविक्षिप्त, व्यस्तचित्त, संरब्ध; 'f with rage' क्रोधोन्मत्त, कोपोन्मादिन्. -ally, *adv.* उन्मत्तवत्, सोन्मादं, ससंरंभं. -ness, *s.* उन्मादः, व्यामोहः, चित्तविप्लवः, उन्मत्तता, वातुलता, चित्तविभ्रमः.

Frater, *s.* परिव्राज् *m.* यति *m.*, 2 बंधु *m.*, बांधवः.

Fraternal, *a.* भ्रात्रीय, भ्रातृसंनिभ, भ्रात्रनुरूप. -ly, *adv.* भ्रातृवत्, सोदरवत्.

Fraternity, *s.* भ्रातृत्वं, सौभ्रात्रं. 2 समाजः, संसर्गः, साहित्यं, बंधुता. -Fraternize, *v. i.* भ्रातृवत् संमिल् 6 P or संयुज् pass. or एकीभू or संमिलत् 1 P.

Fratricide, *s.* भ्रातृघातकः, भ्रातृघातिन् *m.* 2 भ्रातृवधः-हत्या-घातः.

Fraud, *s.* कपटः-टं, छलं, कैतवं, माया, व्याजः, कूटं, वंचनं-ना, उपधिः, प्रतारणं-णा, विप्रलंभः, छद्मन् *n.*, दंभः, कुसृति *f.*, निकृति *f.* -**Fraudulent**, *a.* कपटिन्, सव्याज, शठ, धूर्त, मायिन्, वंचक, प्रतारक, विप्रलंभक, कापटिक-छाद्मिक (की *f.*), कपट in comp.; 'a f. plan' कपटप्रबंधः. -**ly**, *adv.* छलेन, सकपटं, सव्याजं, मायया, धूर्तवत्, समायं, सकैतवं.

Fraught, *a.* धुर्य, धुरीण, भाराक्रांत. 2 आ-सं-परिपूर्ण, आकीर्ण, आ-सं-कुल, गर्भ-आवह- in comp.; 'f. with danger' अनर्थावह.

Fray, *s.* कलहः, कलिः, युद्धं, द्वंद्वं.

Freak, *s.* कामचारः, चापल्यं-लं, मनोलौल्यं, छंदः-दस् *n.*, लहरी, तरंगः, विलासः, विभ्रमः, लीला, स्वैरिता. -*v. t.* चित्रीकृ 8 U, चित्र् 10 -**ish**, *a.* चपल, लोल, चलचित्त, लोलमति, स्वैरिन्, कामचारिन्.

Freckle, *s.* जडुलः, कालकः, पिप्लुः.

Free, *a.* अमर्याद, मर्यादातिक्रांत, विनय-हीन-शून्य, प्रगल्भ, धृष्ट, अविनीत. 2 आत्म-स्व-तंत्र, स्वाधीन, अनधीन, अनायत्त, अपराधीन, स्वेच्छाचारिन्, स्वच्छंद, स्वैरिन्, निरवग्रह, अपावृत, अ-वि-वश. 3 मुक्त, विमुक्त, निर्मुक्त, विमोचित. 4 निर्यंत्रण, अबद्ध, अनिरुद्ध, वि-उत्-शृंखल, अनर्गल, निरर्गल. 5 निर्विघ्न, निष्प्रत्यूह, अप्रतिहत, निरवरोध, असंबाध. 6 निश्चिंत, वीतचिंत, विशद, स्वस्थ. 7 मुक्तहस्त, त्यागशील, व्ययपर. 8 अवतबाध्, असंवृत, अविसंश्रितकाय. 9 मूल्यं विना. 10 सर्वसाधारण-सामान्य; 'f. from' ex. by निर्-अ in comp. or by गत, वीत, हीन, रहित, वर्जित, शून्य, मुक्त, mostly in comp.; 'f. from pride' निरवलेप, अनुद्धत, वीतस्पृह, चिंताहीन, &c., 'f. choice' स्वेच्छा, स्वरुचि *f.*; 'f. course' प्रसरः. -*v. t.* मुच् 6 P or c., वि-निर्°, वि-मुच् 6 P or c., मोक्ष् 10; gen. ex. by निर् or अ pr. to nouns; 'f. from obstacle' विघ्नान् अपनी or हृ 1 P, निर्विघ्नीकृ 8 U; 'f. from debt' अनृण *a.* कृ, ऋणं अपाकृ or निस्तॄ c.; 'I f. ed him from doubt' तं निर्मुक्तसंदेहमकरवं, तस्य संदेहमपानयम्, 'f.-agency,' 'f.will' स्वेच्छा, यदृच्छा, स्वातंत्र्यं, स्वाच्छंद्यं, स्वैरता, स्वकामः; 'f.-booter' दस्युः, साहसिकः, प्रसह्यचौरः; 'f.-booting' प्रसभं अपहारः, साहसं; 'f.-born' जात-जन्म-स्वतंत्र, आत्मा स्वायत्त, जन्मनैव अपरायत्त, कुलीन-जाति, अदासज; 'f.-hearted, -minded' *See* **Frank**; 'f.-hold' निष्करभूमि *f.*, स्वाधीना भूः; 'f.-holder' स्वाधीनक्षेत्रस्वामिन् *m.*; 'f. liver' कुक्षिंभरिः, औदरिकः; 'f.-man' स्वतंत्रः, अपरायत्तः, स्वाधीनः, अदासः; 'f.-spoken' स्फुटवादिन्, स्पष्टवाच्, अगूढभाव; 'f.-thinker' नास्तिकः अनीश्वरवादिन् *m.*; 'f.-woman' स्वाधीना, स्वैरिणी, स्वैरचारिणी. -**dom**, *s.* स्वतंत्रता, अवशता, स्वातंत्र्यं. 2 मोक्षः-क्षणं, वि-मुक्ति *f.*, मोचनं. 3 निर्यंत्रणं-णता, निर्विघ्नता. 4 अविनयः, मर्यादातिक्रमः, प्रागल्भ्यं. 5 विरहः, अभावः, राहित्यं, हानि *f.*, मुक्ति *f.*; 'f. of will or thought' स्वेच्छा, स्वप्रवृत्तिवर्तनं, कामचारः, स्वाच्छंद्यं. -**ly**, *adv.* स्वेच्छया, स्वैरं, स्वच्छंदतः; कामतः अयाचितं. 2 बहुशः, बाहुल्येन, मुक्तहस्तं, भूयसा. 3 यथेच्छं, नि-प्र-कामं, पर्याप्तं, यथेप्सितं, आतृप्ति. 4 निर्विघ्नं, निर्यंत्रणं, अनिवारितं. 5 मूल्यं विना. -**ness**, *s.* निर्विघ्नता, निष्कापट्यं, वाग्यतत्वं, त्यागशीलता, &c.

Freeze, *v. i.* शिलीभू 1 P, घनीभू, संहन् pass., श्यै 1 A, संहतीभू, श्यानीभू, पिंडं बंध् 9 P. -*v. t.* शिली-घनी-कृ 8 U, संहन् 2 P, जडयति (D.), जडीकृ, श्यै c., शिलीकृ; 'a frozen mass of ice' शिलीभूतं हिमं, हिमपिंडः.

Freight, *s.* नौभांडं, नौभारः, पोतद्रव्याणि, नाविकं. 2 तरः, आतरः, तरपण्यं, तारिकं, तार्यं. -*v. i.* (द्रव्याणि) नावि निविश् c. or नि-धा 3 U, द्रव्यैः पूर् 10.

Frenetic, *See* **Frantic.**

Frenzy, *s.* उन्मादः, चित्तविभ्रमः-विप्लवः, उन्मत्तता, आवेशः. -**ed**, *a.* उन्मत्त, भ्रांतचित्त, आविष्ट.

Frequent, *a.* नित्य, अनवरत, सतत, अभीक्ष्ण, बहुशः वर्तमान or वर्तमान; better ex by 'f.-ly.' -*v. t.* सेव् 1 A, नित्यं आश्रि 1 U, सततं भज् 1 U or अभिगम् 1 P, जुष् 6 A; सततं गम् &c.; *See* below. -**ative**, *s.* यङ्लुगंतं, यङंतं. -**ly**, *adv.* पुनः पुनः, मुहुर्मुहुः, भूयोभूयः, नित्यं, असकृत्, वारंवारं, अभीक्ष्णं, सततं, बहुशः, अनेकशः, बहुवारं, प्रायः, प्रायेण, प्रायशः, शश्वत्. -**Frequence**, -**cy**, *s.* पौनः पुन्यं, सातत्यं, अभीक्ष्णता, नित्यता, अविरामः, समभिहारः, अविच्छेदः.

Fresco, *s.* शीतता. 2 मंडोदकचित्रं.

Fresh, *a.* नव, अभिनव, नूतन, नवीन, प्रत्यग्र, अविशीर्ण, अम्लान, अशुष्क (of flowers only); 'f. age' नवं-प्रथमं-वयः; 'f. wound' आर्द्रक्षतं. 2 पेय, आस्वाद्य, अलवण. 3 शीतल, शिव, सुख (of breezes). 4 सरस, अश्रांत, अक्षतवीर्य, अक्लांत, अक्षीणतेजस्; 'a f. man' नवशिष्यः-छात्रः, प्राथमकल्पिकः, शैक्षः (just initiated). -**en**, *v. t.* नवीकृ 8 U, सरसीकृ, (पुनर्नवीकृताः स्मः S. 5). -**ly**, *adv.* सद्यः, नवं, प्रत्यग्रं. 2 शीतलं, सुखं. -**ness**, *s.* नवता, नूतनता, अम्लानता, अक्षीणता. 2 तेजस् *n.*, वीर्यं, सरसत्वं, अक्लांति-अश्रांति *f.* 3 अलवणता. 4 नवरक्तवर्णः.

Fret, *v. i.* क्षुभ् 4 P, पीड् pass., व्यथ् 1 A, दुर्मनायते (D.), अंतः सं-परि-आ-तप् 4 A, क्षुच् 1 P, क्लिश् pass., उद्विज् 6 A, आत्मानं तप् c. or क्षुभ c. 2 घर्षणेन क्षि pass., संघृष् pass. **-***v. t.* संतप् c., क्षुभ् c.; व्यथ् c. (व्यथयति), पीड् 10, बाध् 1 A, क्लिश् 9 P. 2 घृष् 1 P, घर्षणेन तप् c. **-***s.* (Of sea) क्षोभः, वीचिविपलोठनं. 2 (F.-fulness) चित्तव्यथा, आत्मपीडाक्लेशः, उद्वेगः, मनस्तापः, मनःक्षोभः, अशांति *f.*, दुर्मनायितं. 3 प्रतीपता, वक्रभावः. 4 जालं. **-ful,** *a.* आत्मतापिन्, शीघ्रकोपिन्, दुर्मनस्, चंड, शीघ्रक्षुब्ध-संतप्त. 2 वक्रप्रकृति, प्रतीप, वक्रभाव, दुष्प्रकृति, वामशील, जिह्मस्वभाव. **-fully,** *adv.* सचित्तक्षोभं, मनस्तापेन.

Fretty, *a.* व्यत्यस्तरेखारूपेण तष्ट.

Friable, *See* **Fragile.**

Friar, *s.* योगिन्. *m.*, मुनिः, यतिः, संन्यासिन् *n.* तपस्विन् *m.* **-y,** *s.* मठः, आश्रमः, विहारः.

Fribble, *v. i.* *See* **Trifle.**

Friction, *s.* घर्षणं, संघर्षः, आ-अभि-घर्षः-षणं, आ-वि-घट्टनं, परस्परघर्षणं-मर्दनं.

Friday, *s.* शुक्र-भृगु-वारः-वासरः.

Friend, *s.* मित्रं, सखि *m.*, सुहृद् *m.*, स्निग्धः, प्रणयिन् *m.*, हितः, सहायः, सजुस् *m.*, संगिन् *m.* वयस्यः, बंधुः, (term of address) भद्रः-द्रा; 'an old f.' चिरमित्रं; 'a true f.' सन्मित्रं. **-***v. t.* उपकृ 8 U, अनुग्रह् 9 P. **-less,** *a.* मित्र-बंधु-हीन, असहाय, अनाथ, अशरण; *See* **Forlorn.** **-ship,** *s.* सख्यं, मित्रत्वं; मैत्री, मैत्र्यं, बंधुता, सौहृदं, सौहार्दं, स्नेहः, प्रणयः, प्रीति *f.*, प्रेमन् *m.*, *n.*, अनुरागः. 2 साहाय्यं. **-Friendly,** *a.* स्निग्ध, सदय, हितकाम, हितैषिन्, स्नेहशील, सानुराग, सुहृदय, सप्रणय. 2 हित, अनुकूल, अनुग्राहिन्, उपकारक, हितकर; सुखावह, कल्याणकर (री *f.*); 'on f. terms' स्नेहवृत्त्या, मित्रभावेन; 'f. disposed' हितबुद्धि; 'f. dispute' प्रणयकलहः, प्रीतिकलहः. **-***adv.* मित्रवत्, हितवत्, स्निग्धं, प्रियं. **-ness,** *s.* हितेच्छा, हितकामता, हितबुद्धि *f.*. अनुकूलता, मित्रत्वं, प्रणयः, स्नेहशीलता.

Frieze, *s.* स्थूलपट्ट-शाटकः, वराशिः.

Frigate, *s.* महायुद्धनौका.

Fright, *s.* भयं, त्रासः, संत्रासः, शंका, साध्वसं, भीति *f.*, उद्वेगः, दरं; 'take f.' सं-उत्-त्रस् 1, 4 P, उत्त्रस्त-चकित-*a.* भू. **-***v. t.*, **-en,** *v. t.* भी c. (भापयते-भीषयते), सं-उत्-त्रस् c., उद्विज् c. **-ed,** *a.* भीत, त्रस्त, भयार्त, भयाकुल, चकित, ससाध्वस, जातशंक, शंकित, भयाविष्ट. **-ful,** *a.* भीम, विकट, कराल, दारुण, भीषण, घोर, भैरव (वी *f.*), रौद्र (द्री *f.*), भयानक, भयावह, उग्र, भयंकर; 'f. in appearance' करालवदन, भीम-रौद्र-दर्शन, उग्रदर्शन. **-fully,** *adv.* दारुणं, घोरं, उग्रं.

Frigid, *a.* शीत, शिशिर, हिम, जड. 2 निरुत्साह, निःस्नेह; *See* **Cold.** **-ity,** *s.* हिमं, शैत्यं, जडता. 2 विरागः, स्नेहाभावः. **-ly,** *adv.* शीतलं, शिशिरं, निःस्नेहं.

Fringe, *s.* अंचलः-लं, दशाः (*f.* pl.), वस्तयः (*m.* *f.*); 'like a f. rent from the robe of heaven' छिन्ना इवांबरपटस्य दशाः (Mr. 5). **-***v. t.* प्रांतयति (D.); 'f.-ed with gold' सुवर्णमंडितप्रांतं (वस्त्रं).

Frippery, *s.* चीराणि (pl.), जीर्ण-चीर-वस्त्रं, वस्त्रखंडाः, कर्पटाः. 2 निष्प्रयोजनद्रव्यं, उच्छिष्टं.

Frisk, *v. i.* क्रीड् 1 U, इतस्ततः रम् 1 A or नृत् 4 P or प्लु 1 A, खेल् 1 P, वि-हृ 1 P. **-y,** *a.* हृष्ट, प्रहृष्ट, प्रफुल्ल, सानंद.

Frith, *s.* संकटं, संभेदः.

Fritter, *v. t.* खंडशः कृत् 6 P; खंड् 10, शकलीकृ 8 U. 'f. away' खंडशः-अल्पशः-न्यूनीकृ or क्षीणीकृ or क्षै c. (क्षपयति); 'f. away time' अल्पशः (मुधा) वेलां क्षै c. **-***s.* खंडः-डं, शकलः-लं.

Frivol, *v. i.* *See* **Trifle.**

Frivolous, *a.* लघु, अगुरु, अनर्थक, तुच्छ, यत्किंचन, चपल, चपल-लघु-वृत्ति, लघुकर्मन्. **-ness, -Frivolity,** *s.* लाघवं, लघुवृत्तितात्वं, लघुता, यत्किंचनकारिता, चापलं, चपलं कर्म, निरर्थकव्यापारः.

Friz, Frizzle, *v. t.* कुंच् c., व्यावृत् c.

Fro, *adv.* (In 'to and f.') इतस्ततः; 'going to and f.' गमनागमनं.

Frock, *s.* उत्तरीयं, कंचुकः.

Frog, *s.* भेकः, दर्दुरः, मंडूकः, वर्षाभूः, शा(सा)लूरः, प्लवः, प्लवगः, प्लवंगमः, वर्षाघोषः; 'she-f.' मंडूकी.

Frolic, *v. i.* क्रीड् 1 U, विलस् 1 P, विहृ 1 P, खेल् 1 P, रम् 1 A, विभ्रम् 1, 4 P. **-***s.* केलि *f.*, विलासः, क्रीडा, विहारः, वि-भ्रमः, ललिा, खेला, क्रीडाकौतुकं. **-some,** *a.* केलि-विलासप्रिय, विलासिन्, क्रीडा-खेला-पर, उल्लासिन्, विहारिन्, केलिकर; परिहासशील.

From, *prep.* Gen. ex. by abl., when denoting source or place. 2 (Of cause) by abl. or instr., (only by instr., the noun being *f.*); 'f. curiosity' कुतूहलात्-लेन; 'f. its fragrance' सुरभितया. 3 (Of persons) by abl., or सकाशात् with gen.; रामस्य सकाशात् 'f. Râma' 4 (Of time) by आ with abl. or in comp.; 'f. the beginning' आमूलात्; आजन्मनः, आजन्म; gen. by आरभ्य or प्रभृति, with abl.; तद्दर्शनादारभ्य or प्रभृति; 'f. this day' अद्यप्रभृति, अद्यारभ्य; 'f. above' उपरिष्टात्, ऊर्ध्वात् 'f. day to day' दिनेदिने, दिनादिनं; 'f. below' अधस्तात्, अधोभागात्; अधःस्थानात्;

'f. behind' पश्चाद्देश, पृष्ठतः, पृष्ठत आगत्य; f. hence' अतः, इतः; 'f. afar' दूरतः, दूरात्; 'f. without' बहिर्देशात्; 'f. within' अभ्यंतरात्, अंतःप्रदेशात्.

Front, *s.* अग्रं, अग्रभागः-देशः, मुखं, मूर्धन् *m.*; 'f. door or gate' मुखं, निःसरणं. **2** वदनं, आस्यं, मुखं, आननं. **3** शिरस् *n.*, ललाटं; 'in f. of.' पुरः, पुरतः, अग्रे, अग्रतः, पुरस्तात्, प्रत्यक्षं, समक्षं, साक्षात्, अभि-सं-मुखं-खे, (with gen.); 'f. of war' रणधुरा, रणशिरस् *n.*, मूर्धन् *m.n.*, 'f. of army' सेनामुखं, सेनाग्रं, अग्रानीकं (*f.* ranks); 'in the f.' अग्रे, मूर्धनि, धुरि, शिरसि; 'to place in the f.' पुरस्कृ, अग्रणीकृ, अग्रेसरीकृ. *-v.* संमुखं-खे स्था 1 P or वृत् 1 A, संमुखीअभिमुखी-भू; oft. by मुख or अभिमुख in comp.; 'a house f. ing the east' प्राङ्मुखं-प्राच्यभिमुखं-गृहं. **-age,** *s.* अग्रपूर्व-भागः, मुखं. **-al,** *a.* लालाटिक (की *f.*), ललाट in comp. *-s.* ललाटपट्टं; 'f. of an elephant' कुंभः, गंडः. **-less,** *a.* धृष्ट, निर्लज्ज, निस्त्रप. **-let,** *s.* ललाटपट्टं.

Frontier, *s.* सीमा-मन् *f.*, उपांत, पर्यंतः, प्रांतः, समंतः, सामंतः-तं. *-a.* 'Dwelling on the f.' सामंत (ती *f.*), सीमावर्तिन्, पर्यंतस्थ, प्रांतनिवासिन्; *See* **Border.**

Frontispiece, *s.* मुखप्रतिमा-चित्रं; 'f. of a house' गृहमुखं, गृहाग्रभागः.

Frost, *s.* तुषारः, तुहिनं, हिमं, अवश्यायः, नीहारः, प्रालेयं, मिहिका; 'f.-bitten' हिमासिक्त, तुषार-शीत-उपहत. **-y,** *a.* हिम, तुषार, हिम-तुषार-वत्.

Froth, *s.* फेनः-नः, मंडः-डं, उत्सेचनं; *See* **Ferment.** *-v. i.* फेनायते-मंडायते (D.), उत्सिच् pass. **-y,** *a.* फेनिल, फेनमय (यी *f.*), फेनिन्. **2** असार, लघु, निःसार, निःसत्व, अंतःशून्य.

Frouzy, *a.* पूतिगंधि, उग्रगंध.

Froward, *a.* अवश्य, अविनेय, अतिलालित, दुर्ललित, उच्छृंखल, दुर्वृत्त. **2** प्रतीप, प्रतिकूल, वक्रस्वभाव, विलोम, वामशील, प्रतीपाचार. **-ly,** *adv* वक्रभावेन, प्रतिकूलं. **-ness,** *s.* प्रतीपता, वामता, वक्रभावः, अवश्यता.

Frown, *s.* भ्रूभंगः, भ्रु(भ्रु)कुटि-टी *f.*, भ्रूभेदः-क्षेपः-संकोचः. *-v. i.* भ्रुकुटिं बंधू 9 P or रच् 10 or कृ 8 U, भ्रूभंगेन दृश् 1 P, भ्रुवौ संकुच् 1 P; 'Oh he just f. s at myself' अये मय्येव भ्रुकुटीधरः संवृत्तः (U. 5). **-ing,** *a.* नत-आकुंचित-भ्रू, सभ्रूभंग. **-ingly,** *adv.* सभ्रूभंगं, भ्रूक्षेपेण, भ्रुकुटिं बद्ध्वा, सभ्रूक्षेपं.

Fructify, *v. t.* बहुफलवत्कृ 8 U, सफलीकृ, स्फीतीकृ, सफलयति (D.). **-Fructuous, -Fructiferous,** *a.* (बहु) फलद, फलिन्, फलदायिन्.

Frugal, *a.* मित-अल्प-व्यय-व्ययिन्, स्वल्पपरिमित-व्यय, अमुक्तहस्त, कृपण, व्ययविमुख. **-ity,** *s.* मितव्ययिता, मित-स्वल्प-व्ययः, अमुक्तहस्तत्वं, कृपणत्वं. **-ly,** *adv.* अमुक्तहस्तं; मित-स्वल्प-व्ययेन, अल्पव्ययपूर्वं, कृपणं.

Fruit, *s.* फलं (lit. and fig.); श(स)स्यं, प्रसवः, उत्पन्नं. **2** परिणामः, उत्तरफलं, कर्मफलं. **3** (Progeny) अपत्यं, संतानः-नं, संतति *f.*, प्रजा, प्रसूति *f.*; फलं. **4** अर्थः, लाभः, फलागमः, फलप्राप्ति *f.*, 'dry f.' वानं; 'unripe f.' शलाटु; 'bear f.' फल् 1 P, फलं बंध् 9 P or दा 3 U, सफलीभू, पच् pass., (सद्य एव सुकृतां हि पच्यते कांक्षितं R. xi. 50); 'f.-bearer' फलदातृ *m.*, फलदः; 'f.-bearing' फलद, फलेग्रहि, फलभृत्, फलदायिन्, फलिन्, फलशालिन्; 'f.-garden' फलवाटः-टिका; 'f.-season or time' फलकालः-समयः, फलावचयकालः; 'f.-stalk or stem' शस्यमंजरी, प्रसवबंधनं, वृंतं; 'f.-tree' फलदः वृक्षः or वनस्पतिः, फलग्राहिन् *m.* **-age,** *s.* फलोच्चयः, फलभारः-गुच्छः, फलागमः. **-erer,** *s.* फलविक्रयिन् *m.* **-ery,** *s.* फलानि (pl.). **2** फलस्थानं. **-ful,** *a.* फलवत्, फलद, फलिन्, सफल, फलित, अवंध्य, अमोघ, बहुफलद, फालिन, फलेग्रहि. **2** बहुप्रज, प्रजनिष्णु, बह्वपत्य, बहुप्रजोपेत. **3** उत्पादक, जनक; आवह-प्रभवः-मूलं-कारणं in comp. **-less,** *a.* निष्फल, वि-अ-फल, निरर्थक, व्यर्थ, मोघ, वंध्य, अनर्थक, निष्प्रयोजन, निर्गुण, अनुपयुक्त, फलहीन, अवकेशिन्. **-lessly,** *adv.* व्यर्थं, निरर्थकं, मुधा, वृथा, मोघं, निष्फलं. **-lessness,** *s.* वैयर्थ्यं, अनुपयोगः, व्यर्थता, वैफल्यं. **-Fruition,** *s.* उप-भोगः, भुक्ति *f.*, अनुभवः, आस्वादः; सुखोपभोगः, फलास्वादः, सुखानुभवः, सुखास्वादः.

Frumentaceous, *a.* गोधूममय (यी *f.*).

Frump, *s.* कर्कशा, कैकेयी

Frustrate, *v. t.* विफली-निष्फली-मोघी-कृ 8 U, प्रति-व्या-हन् 2 P, भंज् 7 P, खंड् 10, वृथा-मुधा-कृ; *See* **Baffle.** *-a.* **Fruitless,** q. v. **-ed,** *a.* प्रति-व्या-हत, मोघीकृत, वृथाभूत; 'f. in attempts or hopes' भग्नोद्यम, व्यर्थप्रयत्न, भग्नसंकल्प; भग्नाश, अकृतार्थ, मोघाश, खंडिताश, प्रतिहत, प्रतिबद्ध. **-ion,** *s.* भंगः, व्याघातः, विफलीकरणं, खंडनं. **-ive, -ory,** *a.* व्याघातिन्, भंजक, वृथाकारिन्.

Frutescent, *a.* गुल्मावृत.

Fry, *s.* क्षुद्रमत्स्यसंघः, मत्स्यसंघातः, पोताधानं. **2** मीनांडं. *-v. t.* भ्रस्ज् 6 P or c. (भर्जयति), पच् 1 P, भृज्ज् 1 A. **-ing,** *s.* भर्जनं, पचनं; 'f.-pan' पिठरः-रं, भृज्जनं, भ्राष्ट्रः, भर्जनपात्रं, अंबरीषं, ऋजीषं, पिष्टपचनं; (for liquor) स्वेदनी, कंदु-दू *m.-f.* **-ed,** *a.* भ्रष्ट, भर्जित, कंडुपक्व; 'f. grain' धानाः (*f.*, pl.), भ्रष्टयवाः, लाजाः (*m.* pl.).

Fuddle, *v. t.* मद् c., मद्येन मुह् c. –*v. i.* मद् 4 P. **–er,** *s.* पानासक्तः, पानरतः.

Fudge, *s.* अनर्थकं, असंबद्धं. –*v. i.* असंबद्धं जल्प् 1 P.

Fuel, *s.* इंधनं, एधस् *n.*, एधः, इध्मं, समिध् *f.*, समिंधनं; 'add f. to the flames' क्षते क्षारं प्रक्षिप् 6 P.

Fugacious, *a.* पलायनशील, पलायनपर; अस्थिर, चपल, लोल.

Fugitive, *s.* कृतपलायनः, पलायिन् *m.*, कांदिशीकः. –*a.* पलायिन्, पलायनपर-शील. 2 चपल, तरल, चंचल, अस्थिर.

Fulcrum, *s.* आधारः, उपस्तं(ष्टं)भः, आलंबः, आश्रयः.

Fulfil, *v. t.* सं-परि-पूर् 10, साध् 5 P or c., निर्वह् c., निः-सं-पद् c., समाप् c., निर्वृत् c., सफलीकृ 8 U, निस्तॄ c., तीर् 10; 'f. a promise' प्रतिज्ञां निर्वह् c. or तीर् or शुध् c. or पा c. (पालयति) or अप-वृज् 10; gen. in pass. constr. ex. by पूर्ण, कृत, आप्त, लब्ध, in comp.; 'whose desires are f. ed' समवाप्त-लब्ध-मनोरथः-कामः, कृतार्थः, पूर्णमनोरथः-कामः, कृतिन् *m.*; 'who has f.ed his promise' पूर्णप्रतिज्ञः, पालितसंगरः, सत्यप्रतिज्ञः, सत्यव्रतः-संधः. **–ler,** *s.* निर्वाहकः, साधकः, पूरयितृ *m.* **–ment,** *s.* पूरणं, सिद्धि *f.*, निष्पत्ति *f.*, साधनं, निर्वाहः; 'f. of desires' कृतार्थता, कामसिद्धिः, इच्छापूरणं, इष्टावाप्तिः.

Fulgent, *a.* उज्ज्वल, दीप्ति-द्युति-मत्; *See* **Bright.** **–Fulgency,** *s.* तेजस् *n.*, प्रभा, कांति-दीप्ति-द्युति *f.*

Fulgurate, *v. i.* विद्युत् 1 A, स्फुर् 6 P.

Full, *a.* (of) सं-परि-पूर्ण, आ-सं-कीर्ण, आ-सं-कुल, संभृत, व्याप्त, निर्भर, पूरित, मय (यी *f.*) in comp. 2 अशेष, अन्यून, सकल, निखिल, कृत्स्न, समग्र, अविकल, अखंड, संपूर्ण; 'f. year' पूर्णं वर्षं; 'f. speed' पूर्णवेगः; 'f. 8 months old' पूर्णाष्टमास. 3 परिणत, परिपक्व, पक्व, कठोर, प्रौढ, संपन्न. –*s.* पूर्णता, साकल्यं; 'in f.' सविस्तरं, साकल्येन. –*adv.* कृत्स्नशः, सर्वथा, साकल्येन, अशेषतः-षेण, पूर्णं; 'f.-blown' प्रफुल्ल, विकच, विकसित, प्रस्फुट, प्रस्फुटित 'f.-bodied' स्थूलकाय, सबलांग, पुष्टदेह; 'f.-bosomed' पीनस्तन (नी *f.*), पीनकुचकुड्मल; 'f.-fed,' पुष्टांग, हृष्टपुष्ट; 'f.-grown' प्रवृद्ध, प्रौढ, कठोर, परिणत, प्ररूढ; गतशैशव, प्राप्तयौवन, यौवनारूढ, समारूढयौवनारंभ (of men); 'f.-growth' प्रौढि *f.*, प्रौढता, प्रवृद्धि *f.*; 'f.-laden' पूर्णभार, गुरुभाराक्रांत; 'f. moon' पूर्णेन्दुः, सकलेंदुः; 'f. moon day' पौर्णिमा, पूर्णिमा, राका. –*v. t.* वस्त्रं निर्णिज् 3 U. 2 घनीकृ 8 U. **–er,** *s.* रजकः, निर्णेजकः. **–y,** *adv.* अशेषेण, सविस्तरं, अशेषतः, सर्वशः-था, साकल्येन, कृत्स्नशः, निरवशेषं, विस्तरेण-रतः, पूर्णतया. **–ness,** *s.* पूर्णता, निर्भरता, पूर्ति *f.*, संभारः. 2 बाहुल्यं, प्राचुर्यं. 3 परिणामः, परिपाकः, सिद्धि *f.*, प्रौढि *f.*, संपद् *f.*

Fulminate, *v. i.* विकटं रस् or स्तन् 1 P, स्फूर्ज् 1 P. –*v. t.* वज्रनिर्घोषेण इव भेद् c. or उद्दीप् c. **–ion,** *s.* स्फूर्जनं, वज्र-मेघ-निर्घोषः, स्तनितं.

Fulsome, *a.* गर्हित, कुत्सित, गर्ह्य, बीभत्सजनक, विरस. **–ness,** *s.* विरसता, गर्ह्यता.

Fulvous, *a.* आपीत, पिंगल, कपिल.

Fumble, *v. i.* परामृश् 6 P, समालभ् 1 A, अदक्षं कार्यं वि-धा 3 U. **–ing,** *a.* संभ्रांतं परामृशत्, अदक्षतया कार्यविधायिन्. –*s.* अदक्षं कार्यविधानं

Fume, *s.* धूमः-मिका, बाष्पः, धूपः. 2 धूमोद्गारः. 3 क्रोधः, संरंभः. –*v. t.* धूमयति (D.), धूप् 1 P (धूपायति). **–Fumigate,** *v. t.* धूप् 10, धूप् 1 P (धूपायति), धूपेन वास् 10 or धू c.; 'a thing f. ed' वासितं, भावितं. –*v. i.* धूमायते (D.), बाष्पं उद्गृ 6 P. 2 Angry, (to be) q. v. **–ion,** *s.* वासनं, भावनं, अधिवासनं. **–Fumy,** *a.* सधूम, सधूप.

Fun, *s.* परि(री)हासः, नर्मन् *n.*, क्रीडा, खेला, केलि *f.*, प्रहसनं, क्रीडाकौतुकं; 'said in f.' नर्मभाषितं, नर्मालापः. **–Funny,** *a.* हासजनक, विनोदप्रशील, रसिक, कौतुककारिन्, नर्म-परिहास- in comp. 2 उपहास्य, अपरूप.

Funambulist, *s.* रज्जु-चारिन् *m.*-नर्तकः.

Function, *s.* व्यापारः, कर्मन् *n.*, कार्यं, कृत्यं, चेष्टा, क्रिया, चेष्टितं, व्यवसायः, व्यवहारः, वृत्ति *f.*, प्रवृत्ति *f.* 2 नियोगः, अधिकारः, पदं. 3 आचरणं, अनुष्ठानं, करणं. 4 गुणः, धर्मः, स्वभावः. 5 इंद्रियं, शक्ति *f.*, कर्मेंद्रियं. **–ary,** *s.* नियोगिन् *m.*, अधिकारिन् *m.* कार्यनिर्वाहकः, नियुक्तः, अधिकृतः.

Fund, *s.* संचयः, पुंजः, राशिः, समुदायः, निचयः, संयोगः, संनिपातः; *See* **Collection.** 2 मूलधनं, नीवि-वी *f.* –*v. t.* सं-चि 5 U, संग्रह् 9 P, पुंजीकृ 8 U, राशीकृ.

Fundament, *s.* गुदं, पायुः, अपानं, मलद्वारं. 2 अधोभागः, तलं.

Fundamental, *a.* प्रधान, सार, सारभूत, मुख्य, मौलिक, मूल in comp.; 'f. cause' मूलकारणं; 'f. principle' मूलतत्वं. –*s.* प्रधान-मूल-तत्वं, मूलं, तत्वं, सारः.

Funeral, *s.* और्ध्वदेहिकक्रिया, अंत्येष्टि *f.*, प्रेतकार्य-कृत्यं, प्रेतनिर्हारः, अंत्यक्रिया, उत्तरक्रिया-कर्मन् *n.*, और्ध्वदेहिकं, श्राद्धादि कर्म. –*a.* और्ध्वदेहिक, और्ध्वदैहिक (की *f.*), better by (*s.*); 'f. pile' चिता, चिति-ती *f.*, चित्या.

Fungus, *s.* विड्जं, गोमयजं, शिलीध्रं, शा-(सा)लेयः, शीतशिवः, छत्रा, मधुरिका, मिसि-शि-सी-शी- *f.*, मिश्रया.

Funicle, *s.* क्षुद्ररज्जु *f.*, क्षुद्रगुणः, सूत्रं.

Funk, *s.* महद्भयं, संत्रासः. **-y,** *a.* भीत, संत्रस्त.

Funnel, *s.* धूममार्गः-पथः-द्वारं. **2** नाली, प्रणाली-लिका, नाडि-डी *f.*

Fur, *s.* रो (लो) मन् *n.*, तनुरुहः-हं, पशु-लोमन् *n.*; 'f. on the tongue' कुलुकं, मलं. **-red,** *a.* लोमावृत, लोमान्वित. **2** समल.

Furbish, *v. t.* तिज् c., निः-तप् c., प्रमृज् 2 P or c., धाव् 10, परिष्कृ 8 U. **-ed,** *a.* निर्धौत, प्रमृष्ट, निष्टप्त. **-er,** *s.* तेजकः, मार्जकः, निर्णेजकः; 'f. of weapons' शस्त्रमार्जः, असिधावकः. **-ing,** *s.* धावनं, परिष्कारः, तेजनं.

Furcated, *a.* द्व्यग्र.

Furl, *v. t.* सं-वेष्ट् c., सं-वृ 5 U, संपुटीकृ 8 U, सं-हृ 1 P.

Furlong, *s.* नल्वः.

Furlough, *s.* कर्मत्याग-कर्मविराम-अनुज्ञा. **2** कर्मनिवृत्ति *f.*

Furmenty, *s.* क्षीरान्नं, परमान्नं, पायसं.

Furnace, *s.* अग्निकुंडं, अधिश्रयणी, अंति (दि)का, उष्मानं; 'a portable f.' *See* **Hearth.**

Furnish, *v. t.* (उपकरणैः) संयुज् 10 or सनाथीकृ 8 U; (उपस्करं) उप-क्लृप् c., उप-पद् c., सं-भृ 3 U, वि-धा 3 U; gen. ex. by स or सनाथ in comp.; 'f. ed with arrows' सशरं (धनुः); मणिशिलापट्टसनाथं लतागृहं (V. 2) 'f. ed with a marble slab'; 'to f. with arms' शस्त्रैः संनह् 4 P or सज्जीकृ. **-ed,** *a.* सं-,युक्त, समन्वित, उपेत, उप-परि-क्लृप्त, सनाथ, संभृत, स in comp. **2** सोपस्कर, सोपकरण, उप-स्करादियुक्त. **3** सन्नद्ध, सज्जीकृत. **-Furniture,** *s.* उपस्करः, उपकरणं, परि-च्छदः, सामग्री, सज्जा, संभारः, उपचारः, परिबर्हः; 'on sofas with all f.' उपचारवत्सु मंचेषु (R. vi. 1.); परिबर्हवंति वेश्मानि (R. xiv. 15); 'household. f.' गृहोपस्करः, पारिणाह्यं.

Furor, *s.* *See* **Fury.**

Furore, *s.* अत्याश्चर्यं, महद्विस्मयः,

Furrow, *s.* सीता, हलिः, लांगलमार्गः-पद्धति *f.*, हलरेखा. **2** रे (ले) खा, सुषिरं. **3** वदन-रेखा, वलि-ली *f.* **-v. t.** (हलेन) कृष् 1 P, (लांगलेन) लिख् 6 P or रेखाः कृ 8 U. **-ed,** *a.* सीत्य, कृष्ट, हल्यवत्.

Further, *a.* दूरतर, दूरस्थ, दवीयस्. **2** अधिक, अपर, अधिकतर, पर. **-adv.** दूरतरं, अधिकदूरं, अग्रे-ग्रतः, पुरतः. अग्रेतरां, पुरस्तात्; 'a little f. on' स्तोकांतरं, अग्रतः, किंचिदग्रे, 'f. and f.' अधिकाधिकं, उत्तरोत्तरं. **2** अपरं, अन्यच्च, अपरं च, किं च, अपि च, अपरं तु. **-v. t.** प्र-सं-वृध् c., अनुग्रह् 9 P, उपकृ 8 U, त्वर् c., (त्वरयति) पुरस्कृ, प्रवृत् c., साहाय्यं दा 3 U, उत्कृष् 1 P, उन्नतिं-उत्कर्षं-नी 1 P. **-ance,** *s.* स-प्र-वर्धनं, प्रवर्तनं, अभि-प्र-वृद्धि *f.*, अनुग्रहः, उपकारः, साहाय्यं, उत्कर्षः. **-er,** *s.* उपकारकः, प्रवर्धकः. **-more,** *See* (*adv.*).

Furthest, *a.* दविष्ठ, दूरतम. **-adv.** सुदूरं, दविष्ठं.

Furtive, *a.* चौर्येण गृहीत, अपहृत, छलापहृत, निभृतं कृत. **-ly,** *adv.* चौरवत्, उपांशु, रहसि, निभृतं, छलेन.

Fury, *s.* मत्तता, उन्मत्तता, चंडता, उग्रता, औत्कट्यं. **2** संरंभः, कोपः, क्रोधः, रोषः, आवेशः, अमर्षः. **3** महावेगः. अत्यंतवेगः-जवः, बलं, आ-य. **4** चंडी, दुर्गा. **-Furious,** *a* प्र-,चंड, तीव्र, उग्र, प्रबल, महावेगवत्. **2** उन्मत्त, मत्त, मद स्कट, मदकल, समद, उद्ग्रमद, उन्मादसंरब्ध, उत्कट. **3** कोपाकुल, संरब्ध, क्रोधाविष्ट, कोपपरीत, रोषण, दृढ-कोप, जातामर्ष. **-ly,** *adv.* उग्रं, चंडं महावेगेन, संरंभेण. **-ness,** *s.* संरंभः, उग्रता, उन्मादः, कोपाकुलत्व.

Fuscous, *a.* आकृष्ण, आनील.

Fuse, *v. t.* वि-द्रु c., विलीं c, जलसात् कृ 8 U. **2** एकरूप *a.* कृ, संमिश्र् 10, सायुज्य कृ, संयुज् 10, सदृशीकृ **-v. i.** वि-द्रु 1 P, वि-ली 4 A, द्रवीभू, गल्-स्रु- 1 P. **2** सदृशीभू, सायुज्यं प्राप् 5 P, एकरूप *a.* भू. **-ible,** *a.* द्राव्य, विलयनीय, द्रवशील, क्षरण-शील. **-ion,** *s.* द्रावः, विलयनं, विलयः, द्रवत्वं, क्षरणं. **2** एकरूपता, सदृशीभावः, एकभावः, संमिश्रणं, संकरः, संयोगः.

Fuss, *s.* आडंबरः, तुमुलं, कोलाहलः, संभ्रमः. **-y,** *a.* संभ्रमकारिन्.

Fust, *s.* स्तंभः, स्तंभदंडः. **2** उग्र-पूति-गंधः, दुर्गंधः. **-Fusty,** *a.* पूति, पूतिगंधि, उग्रगंध. **-ness,** *s.* पूति *f.*, दुर्गंधः.

Fustian, *s.* स्थूलशाटकः. वराशिः, स्थूलपट्टं-वस्त्रं-कार्पासं. **2** अतिशयोक्ति *f.*, गर्वोक्तिः, दर्पवचनं, सदर्पावाच्-उक्ति *f.* **-a.** स्थूल-कार्पासिक (की *f.*). **2** अतिगर्वित, दर्पाध्मात, सगर्व.

Futile, *a.* निरर्थक, मोघ, व्यर्थ, निर्गुण. **2** असार, लघ्वर्थ, निःसार, निःसत्त्व, फल्गु, तृणप्राय, तुच्छ. **-ity,** *s.* मोघता, लाघवं, असारता, &c.

Future, *a.* भविष्यत्, उत्तर, अनागत, आगामिन्, भाविन्, उत्तरकालीन, श्वस्तन (नी *f.*); 'f. time' अनागतवेला, उत्तरकालः, आयति

f. 2 पारलौकिक-पारत्रिक-आमुष्मिक (की *f.*), अमुत्रत्य, परलोकगत. **-s.**, **-ity,** *s.* भावि-उत्तर-कालः, भविष्यत्-आगामि-कालः, भाविन् *n.*, अनागतं, अनागतकालः, आयति *f.*, उदर्कः; 'past, present and f.' समतीतं च भव्यं च भावि च (R. VIII. 78); 'ignorant of the f.' अश्वस्तनविद्, उदर्कानभिज्ञ.

—— ——

G.

Gaberdine, *s.* वराशिः, स्थूलशाटकः.
Gabble,-er, *See* **Babble,-er.**
Gabel, *s.* करः, राजस्वं, शुल्कः-ल्कं, बलिः.
Gable, *s.* गृह-प्रासाद-शिखरं.
Gad, *s.* बाणाग्रं, शूलाग्रं; अग्रं, कणः. 2 कीलः, लोहकीलः. **-v.** *i.* अट् 1 P, परिभ्रम् 1, 4 P. **-ding,** *s.* परि-, अटन-भ्रमणं.
Gad-fly, *s.* दंशकः, गोमक्षिका, दंशः-शी, वनमक्षिका.
Gaffer, *s.* वृद्धजनः; अशिष्टाचारः.
Gag, *s.* मुखबंधनी-पिधानं, रोधनं. **-v.** *t.* मुखं बंध् 9 P or निरुध् 7 U or पि-धा 3 U.
Gage, *s.* पणः, आधिः, परिपणनं. 2 मानं, प-परि-माणं. 3 मापनयंत्रं. 4 आह्वानं. **-v.** *i.* पण् 1 A, प्रति-ज्ञा 9 U, अंगीकृ 8 U, प्रति-पद् 4 A, सशपथं प्रतिज्ञा.
Gaggle, *v. i.* कलं कृ 2 P; कूज् 1 P.
Gain, *v. i.* लभ् 1 A, अर्ज् 1 P or c., आप् 5 P, आ-सम-सद् c.; *See* **Get;** 'g. ground' उप-चि pass., प्रवृध् 1 A; प्रसृ 1 P; 'g. over' भाव् c., वशं नी 1 P (धनदानादिना); अनुरंज् c., ग्रह् 9 U; 'g. over to one's side' स्वपक्षं ग्रह् c.; 'g. a battle' युद्धे जयं लभ्; 'g. the day' जयं प्राप्, विजयिन् *a.* भू; 'g. upon one's steps' समासद् c.; *See* **Overtake.** **-v.** *t.* क्रमशः प्रसृप् or प्रगम् 1 P. **-s.** लाभः, प्राप्ति *f.*, फलं, आयः, अर्थः, उत्पन्नं, फलोदयः, अर्जनं. **-er,** *s.* अर्जकः; प्राप्तलाभः; फलप्रापकः. **-ful,** *a.* फलद; लाभजनक, अर्थोत्पादक. **-ly,** *adv.* दक्षं, चतुरं, सपाटवं.
Gainsay, *v. t.* विरुध् 7 U; नि-प्रति-षिध् 1 P, प्रत्या ख्या 2 P, प्रत्यादिश् 6 P, अपवद् 1 U, अपलप् 1 P, अधरीकृ 8 U, निरा-कृ, बाध् 1 A, निरस् 4 U. **-er,** *s.* अपवादकः, निषेधकः.
Gairish, *a.* अतिशोभन, रूपगर्वित. **-ness,** *s.* अतिशोभा, रूपगर्वः, दंभः.
Gait, *s.* गति *f.* गमनं, : गतं, चारः; 'graceful in g.' हंसगति, चारुगामिन्.
Gala, *s.* उत्सवः, उत्सवदिवसः, पर्वदिनं.
Galaxy, *s.* सुरनदी, आकाशगंगा, स्वर्गंगा, वियद्गंगा. 2 सुवस्तुमंडलं.
Gale, *s.* वातः, वायुः, पवनः; 'strong g.' वात्या, वाताली, चंडवातः, जवानिलः, वेगा-निलः, प्रकंपनः, ध्राजि *f.*
Gall, *s.* क्षतं, विषं; दंशः,(fig.) पीडा, दुष्टभावः, संबाधा. 2 पित्तं, मायुः. 3 कटुता, तिग्मता, कठोरता, अरुंतुदत्वं. **-v.** *t.* क्षतं घृष् 1 P or कृष् 1 P. 2 सं-परि-तप् c., पीड् 10, बाध् 1 A, क्लिश् 9 P, अर्द् 1 P, मर्माणि कृत् 6 P or भिद् 7 P. **-v.** *i.* आत्मानं तप् c. **-ing,** *a.* परुष, मर्मच्छिद्-भिद्, अरुंतुद.
Gallant, *a.* शोभन, सुभगदर्शन; सभ्य, सभ्या-चार, सुशील; दक्षिण; कुयुपचारपर-दक्ष. 2 वीर, शूर, विक्रांत, महावीर्य; *See* **Brave.-s.** वल्लभः, रमणः, कामुकः, कामिजनः, कामिन् *m.*, नायकः, दयितः. 2 जारः, विटः, उप-पतिः. 3 सभ्याचारः,सुजनः; कुयुपचारशीलः-परः. **-ry,** *s.* दाक्षिण्यं; कामचेष्टा, शृंगार-विलसितं, कुयुपासना, कुयुपचारः. 2 वीर्यं, शौर्यं, धामन् *n.*, विक्रमः, पौरुषं. 3 उदारता, माहात्म्यं. **-ly,** *adv.* सविक्रमं, सवीर्यं, शूर-वीर-वत्. 2 रमणवत्.
Gallery, *s.* मंचाः (pl.), मंचसनाथः कोष्ठः. 2 छन्नपथः-मार्गः. 3 अलिंदः-दकः.
Gallinaceous (fowl), *s.* कुक्कुटः, ताम्र-चूडः, चरणायुधः.
Gallinule, *s.* दात्यूहः, कालकंठकः.
Gallop, *v. i.* वल्ग् 1 P, द्रुतगत्या चल् or धाव् 1 A, प्लु 1 A. **-s.** प्लुतं, वल्गितं, द्रुवनं.
Gallows, *s.* वधस्तंभः, वध्यशिला-काष्ठं, वध-घातस्थानं, वध्यस्थलं. 'met his death on the g.' शूलमारोपितः.
Galoche, *s.* काष्ठपादुका, पादुका.
Galvanize, *v. t.* विद्युच्छक्त्या आक्रुष् 1 P or उपहन् 2 P.
Gamble, *v. i.* दिव् 4 P (अक्षैः अक्षान् वा); अक्षैःक्रीड् 1 P. **-er,** *s.* द्यूतकारः, देवितृ *m.*, धूर्तकृत् *m.*, धूर्तः, अक्षदेविन् *m.*, कितवः, अक्षधूर्तः. **-ing,** *s.* द्यूतं, दुरोदरं, पणः, अक्ष-वती, अक्षक्रीडा-द्यूतं, कैतवं, देवनं, द्यूतसेवा, 'g.-house' द्यूतशाला-सभा; 'he who keeps a g.-house' सभिकः, द्यूतकारकः.
Gambol, *v. i.* क्रीड् 1 P, नृत् 4 P, इतस्ततः. वल्ग् 1 P, प्लु 1 A. **-s.** नृत्यं, क्रीडा, लास्यं लीला, केलि *f.*, खेला.
Game, *s.* क्रीडा, खेला, केलि *f.*, लीला, वि-लासः, परि(री)हासः. 2 वन्यपश्वादि, जांगलः, वन्यपक्षिन् *m.* 3 मृगया. 4 संकल्पः, व्यवसायः, कल्पना, संदिग्धव्यवसायः. **-v.** *i.* क्रीड् 1 P, दिव् 4 P; 'G.-cock' चरणा-युधः, योधकुक्कुटः; 'g.-keeper' वन्यपक्षि-पालकः; 'g.-leg' पंगुपादः. **-ing,** *s.* द्यूतं. **-ster,** *s.* धूर्तः; *See* under **Gamble.**

-some, *a.* क्रीडा-लीला-पर, विलासशील, विलासिन्, परिहासशील, उल्लासिन्, परिहासिन्, विनोदिन्, नर्मालापिन्.

Gammer, *s.* वृद्धा स्त्री.

Gammon, *s.* वल्लूरं, उत्तप्तं, सूकरशुष्कमांसं. 2 चर्मपट्ट-शारि-क्रीडा. 3 **Deceit**, q. v. -*v. t.* सूकरमांसं लवणीकृ 8 U. 2 **Cheat**, q. v.

Gamut, *s.* ग्रामः.

Gander, *s.* हंसः, चक्राङ्गः, चक्रवाकः, चक्रः; श्वेतगरुत् *m.*, मानसौकस् *m.*, राजहंसः (white).

Ganesh, *s.* गणेशः, गणपतिः, विनायकः, विघ्नेशः, विघ्नराजः, द्वैमातुरः, गणाधिपः, एकदन्तः, हेरम्बः, लम्बोदरः, गजाननः, गजास्यः, गजवक्त्रः.

Gang, *s.* गणः, संघः, निवहः; *See* **Collection**.

Ganges, *s.* गंगा, मंदाकिनी, त्रिपथगा, स्वर्णदी, सुरदीर्घिका, जाह्नवी, जह्नुतनया-कन्या, भागीरथी, अमरापगा, सुरनदी, त्रिस्रोतस् *f.*, त्रिपथगा.

Ganglion, *s.* शिरास्फोटः.

Gangrene, *s.* पूतिमांसं ; मांसपाकः; कोथः. -*v. i.* कोथीभू 1 P, पूतीभू.

Gangway, *s.* आरोहावरोहपथः.

Gaol,-er, *See* **Jail,-er**.

Gap, *s.* छिद्रं, भंगः, विच्छेदः, भेदः, रंध्रं, छेदः, विवरं, गर्तः-र्ता.

Gape, *v. i.* वि-प्र-जृम्भ् 1 A; जभ्-जंभ् 1 A, मुखं व्यादा 3 A. 2 वि-,दल् 1 P, स्फुट् 1 P. -*s.*, **-ing**, *s.* जृंभः-भा, जृंभणं, जृंभिका, जृंभितं, हर्मन् *n.*, हाफिका, मुखव्यादानं. **-ing**, *a.* जृंभिन्, जृंभित, व्यात्तमुख.

Garb, *s.* वेशः-षः, वस्त्रं, वसनं, वासस् *n.*, परिधानं, प्रसाधनं; 'putting on the g. of virtue' धर्मकंचुकप्रवेशिनः (S. 5).

Garbage, *s.* उच्छिष्टं, मलं.

Garble, *v. t.* साचीकृ 8 U; सत्यं गुह् 1 U, विकृ, वक्रीकृ.

Garden, *s.* उद्यानं, उपवनं; 'g. near a house' गृहारामः, निष्कुटः, गृहवाटिका; 'pleasure-g.' क्रीडोपवनं, आरामः, प्रमदवनं, आक्रीडः; 'flower-g.' पुष्पवनं-वाटः-वाटिका, कुसुमाकरः; 'fruit-g.' फलवृक्षवाटिका; 'vegetable g.' शाकवाटिका, शाकशाकटं, शाकशाकिनं; 'g.-wall' उद्यानपरिसरः-प्राकारः. **-er**, *s.* उद्यानपालकः-रक्षकः, मालाकारः, मालिकः, मालिन् *m.* **-ing**, *s.* उद्यानकर्मन् *n.*, उद्यानसेवनं-कर्षणं, फलोत्पत्तिकर्मन् *n.*

Gargle, *v. i.* (जलं) आचम् 1 P, उप-स्पृश् 6 P, जलेन मुखं मुष् 2 P or धाव् 1 P. -*s.* आचमनीयं, आचार्यं.

Garish, *a.* *See* **Gairish**.

Garland, *s.* माला, स्रज् *f.*, माल्यं, आपीडः; शेखरः, हारः; 'g. worn in the hair' प्रभ्रंशकः; 'g. hanging from the crest' प्रभ्रष्टकं, शिखालंबि माल्यं; 'g. worn straight' प्रालंबः-बिका; 'g. worn sideways' वैकक्षिकं; 'g. of pearls' हारः, मुक्तावली, मौक्तिकसरः.

Garlic, *s.* ल(र)शुनं, रसोनः-नकः, महौषधं-गृंजनं, अरिष्टः, महाकंदः, सोनहः.

Garment, *s.* वस्त्रं, वासस् *n.*, वसनं, पटः, परिधानं, परिच्छदः, अंबरं, प्रच्छादनं; वेशः-षः; 'under or lower g.' अंतरीयं, अधोंशुकं, उपसंव्यानं, परिधानं, अधोवासस् *n.*-वसनं; 'upper g.' उत्तरीयं, प्रावा(व)रः, उत्तरासंगः, बृहतिका, संव्यानं; 'g. as a protection from wind and cold' नीशारः.

Garner, *s.* कुशू(सू)लः, धान्यागारं, धान्यकोष्ठः, कंडोलः-लकः; पिटः. -*v. t.* कंडोले निविश् c. or नि-धा 3 U.

Garnet, *s.* रक्तमणि *m.*

Garnish, *v. t.* भूष् 10, मंड् 10, अलङ्कृ 8 U, परिष्कृ, शुभ् c. -*s.*, **-ment,-Garniture**, *s.* प्रसाधनं, भूषणं, अलंकारः, मंडनं, आभरणं, उपकरणानि (pl.), सज्जा.

Garret, *s.* शिरोगृहं, चंद्रशाला, अट्टः, अट्टालः.

Garrison, *s.* दुर्गरक्षकाः (pl.); दुर्गसैन्यं-बलं. रक्षिणः-रक्षकाः (pl.); रक्षिवर्गः. -*v. t.* रक्ष् ; पुरुषैः युज् 10, (दुर्गे) रक्षिणः निविश् c. or-स्था c. (स्थापयति).

Garrulous, *a.* अतिवक्तृ, वावदूक; बहुभाषिन्-वादिन्, वाचाल, वाचाट, जल्पाक, मुखर. **-ness, Garrulity**, *s.* वाचालता, वावदूकता, अतिवादः, बहुभाषित्वं, अतिजल्पनं.

Garter, *s.* पादावरणबंधनी, जंघाबंधनी.

Garth, *s.* अंगणं, प्रांगणं. 2 उपवनं. 3 धरणः.

Garuda, *s.* गरुडः, गरुत्मत् *m.*, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागांतकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, भुजगदारणः, भुजगारिपुः.

Gas, *s.* वायुः. **-eous**, *a.* वायुरूप.

Gash, *s.* दीर्घच्छेदः, दीर्घं गंभीर-क्षतं.

Gasometer, *s.* वायुमापनयंत्रं.

Gasp, *v. i.* कृच्छ्रेण श्वस् or अन् 2 P, दुःखेन श्वस्, स्थूलस्थूलं निश्वस्. -*s.* उच्छ्वासः, निश्वासः, कृच्छ्रोच्छ्वासः, कष्टश्वासः.

Gastric, *a.* जाठर (री *f.*), उदरीय, जठरीय, उदर-जठर in comp.; 'g. juice' जठराग्निः.

Gastronome, *s.* औदरिकः, उदरंभरिः, कुक्षिंभरिः, उदरपरायणः; *See* **Glutton**. **-Gastronomy**, *s.* उदरपरायणता, उदरसेवा.

Gate, *s.* द्वारं, प्रतिहारः, द्वार् *f.*; 'g.-way' तोरणः-णं, गोपुरं, निर्गमः, द्वारपथः; for other comps. : *See* **Door**.

Gather, *v. t.* चि 5 U, सं-अव-प्र-आ-°; समाहृ 1 P, समा-नी 1 P, संग्रह् 9 P, सं-भृ 1, 3 U, एकीकृ 8 U; *See* **Collect**; 'g. flowers' पुष्पाणि चि or लू 9 U. **2** ज्ञा 9 U; अनु-मा 3 A, 2 P, ऊह् 1 A, अवगम् 1 P. **3** उद्-भृ 5 U, उद्धृ 1 P. –*v. i.* संगम् 1 A, सं-इ 2 P, संमिल् 6 P, सन्नि-पत् 1 P, एकत्र मिल्, एकस्थ *a.* भू 1 P, एकीभू **2** उपचि pass., प्र-वि-वृध् 1 A, एध् 1A. **3** पूयं बंध् 9 P, पूय् 1 A. –*s.* पुटः, चूणः. –**er,** *s.* अवचायिन् *m.*, संग्राहकः; 'g. of taxes' शौल्किकः, करग्राहकः. –**ing,** *s.* चयः, अवस-चयः, संग्रहणं. **2** समूहः, गणः, संघः, समागमः, निवहः, संघातः; जनसमूहः, लोकनिवहः-संघः.

Gaud, *s.* बाह्यशोभा. –**y,** *a.* उज्ज्वल, शोभन, नानावर्ण, चित्र; 'having a g. dress' उज्ज्वलवेशधारिन्, आर्य उदार-नेपथ्यभृत् –*s.* **Festival,** q. v. –**ness,** *s.* अतिशोभा, औज्ज्वल्यं, चित्रता, नानावर्णता.

Gauge, *See* **Measure.**

Gaunt, *a.* क्षाम, कृश, क्षीण, शुष्कमांस, क्षुत्क्षाम, कृश-क्षिण-देह.

Gauntlet. हस्तत्राणं; 'throw down the g.' युद्धार्थं आह्वे 1 A, 'take up the g.' युद्धाह्वानं अंगीकृ or उरीकृ 8 U.

Gawk, *s* मूर्खः; *See* **Fool. 2 Cuckoo,** q. v.

Gawky, *a.* स्थूल-दीर्घ-देह, स्थूल.

Gay, *a.* प्रमोदिन्, प्रहृष्ट, आनंदित, उल्लासित, प्रमुदित, सानंद, प्रफुल्ल, अनुत्सुक, सोल्लास. **2** विलासिन्, परिहासशील, विनोदन-शील-पर, केलिपर. **3 Gaudy,** q. v. –**Gaiety,** *s.* प्रमोदः, उल्लासः, प्रहर्षः, आनंदः, आह्लादः **2** उत्सवः; *See* **Festival.** –**Gaily,** *adv.* सहर्षं, सोल्लासं, सानंदं, प्रफुल्लतया. **2** उज्ज्वलं, शोभनं.

Gaze, *v. i.* निर्-ईक्ष् 1 A, निर्वर्ण् 10, निध्यै 1 P. बद्ध-स्थिर-दृष्ट्या दृश् 1 P or आलोक् 1 A, 10; दृष्टिं or लक्ष्यं बंध् 9 P. (loc.): 'g. ing up to heaven' नभोदत्तदृष्टिः; 'g. ing in all directions' दिक्षु दृष्टिं क्षिप्त्वा. –*s.* निरीक्षणं, निर्वर्णनं. आ-अव-लोकनं; दृष्टि *f.*, प्रेक्षणं, दर्शनं; बद्ध-स्थिर-अनिमेष-दृष्टिः; 'with a fixed g.' अनिमेषनयन, बद्धदृष्टि *a.*

Gazelle, *s.* मृगः, हरिणः.

Gazette, *s* वार्ताहरः. वार्तापत्र.

Gear, *s.* उपकरणं, सामग्री, सज्जा, प्रसाधनं. **2** कार्यं, व्यापारः; 'out of g.' विलग्न, असंगत, असंबद्ध.

Gelatinous, *a.* सांद्र, श्यान, संलग्नशील.

Geld, *v. t.* वृषणौ छिद् 7 P or कृत् 6 P or उत्पट् 10. –**ing,** *s.* छिन्नमुष्कः (अश्वः).

Gelid, *a.* अतिशीत, हिम, शिशिर.

Gem, *s.* रत्नं, मणि *m. f.* **2 Bud,** q. v. –*v. t.* रत्नैः शुभ् c. –**med,** *a.* रत्नखचित, मणिभूषित, रत्नानुविद्ध. –**my,** *a.* मणिमय (यी *f.*), रत्नभासिन्, रत्नोज्ज्वल.

Gemmate, *a.* मुकुलित, बद्धपल्लव.

Gemini, *s.* मिथुनं, द्वंद्वं, युग्मं, युगलं, युग्मं, द्वयं, यमकं-लं, यमौ, यमजौ-लौ. –**Geminate, –Geminous,** *a.* द्विगुण, द्विरावृत्त, द्विक, यम, यमज-ल.

Gender, *s* लिंगं, प्रकृति *f.* –*v. t.* **Beget,** q. v. –*v. i.* **Copulate,** q. v.

Geneology, *s.* वंशावलि-ली *f.*, वंशक्रमः, वंशश्रेणी परंपरा-वृक्षः; oft. ex. by वंशः, अन्वयः. –**ical,** *a.* (*s.*) in comp. –**ist,** *s.* अन्वयज्ञः, वंशक्रमज्ञः, वंशावलिरचकः.

General, *a.* सामान्य, साधारण, सर्वजनीन-न, सार्वत्रिक-सार्वलौकिक-औत्सर्गिक- (की *f.*), सर्व बहु-सामान्य, व्यापक, सर्वव्यापिन्, अविशेषक, प्रायिक, सर्वत्र प्रचलित; 'a g. rule' उत्सर्गः; 'a g. practice' लोकाचारः, जनरूढि *f.*, जनव्यवहारः, लोकः; 'against g. practice' लोकविरुद्धं; 'g. opinion' बहुमतं; 'g. reader' चुंबकः. –*s* सेनापतिः, सेनाध्यक्षः, चमूपतिः, सेनानीः, बलाध्यक्षः-नायकः. –**ity,** *s.* बहुतरभागः, मुख्यांशः, प्रधानभागः; better by 'g. ly' 'the g. of beasts' प्रायः सर्वे पशवः **2** सामान्यता, साधारण्यं. –**ize,** *v. t.* जातीः निर्दिश् 6 P. जातिशः गणीकृ 8 U, साधारणधर्मं प्रदृश् c., वर्गीकृ. **2** सामान्यतः वद् 1 P. उत्सर्गरूपेण कथ् or निरूप् 10. –**ization,** *s.* जातिनिर्देशः, गणीकरणं, सामान्यधर्मकथनं, सामान्यवादः. –**ly,** *adv.* 'in g.' प्रायः, प्रायेण, प्रायशः, सामान्यतः, बहुशः, भूयसा, भूयिष्ठं, साधारण्येन; oft. ex by हि. –**ness,** *s.* व्यापकत्वं, सामान्यता. –**ship,** *s.* सैनापत्यं, सेनाध्यक्षत्वं. **2** रणकौशलं, युद्धनैपुण्यं, बलविन्यासकौशलं.

Generate, *v. t.* उत्पद् c, प्र-सू 2, 4 A, आवह् 1 P, सं-उद्-भू c., जन् c. (जनयति); *See* **Cause** also. –**ion,** *s.* उत्पादनं, प्रसवः, जननं, जन्मन् *n.*, उत्पत्ति *f.*, प्रसूति *f.*, संभवः, उद्भवः. **2** अन्वयः, कुलं, वंशः, जाति *f.*, संतानः, संतति *f.* **3** पुरुषाः, पुरुषपरंपरा, वंशश्रेणी; 'former g. s' पूर्वे पुरुषाः; 'a pair, one g. removed from the creator' स्रष्टुरेकांतरं द्वंद्व (S. 7). **4** समकालीनपुरुषाः. –**ive,** *a.* उत्पादक, जनक; 'g. organ' उपस्थः योनि *f.* –**or,** *s.* जनयितृ *m.*, जनकः उत्पादकः, जन्मप्रदः-दातृ *m.*

Generic,-al, *a.* जातिगत, सामान्य, साधारण, व्यापक, वर्गीय; 'g. property' जातिधर्मः

-लक्षणं-स्वभावः, जातित्वं, सामान्यधर्मः-लक्षणं. -ally, *adv.* जातिमुद्दिश्य, सामान्यतः.

Generous, *a.* उदार, वदा(द)न्य, त्यागशील, अवदात, दानशील, दानरत, दानशौंड, स्थूललक्ष्य, बहुप्रद्. 2 महात्मन्, उदारधी-चेतस्, महामनस्, उदारचरित, महेच्छ, महाशय. 3 कुलीन, महाकुल, अभिजात. -ness, -Generosity, *s.* औदार्यं, त्यागिता, त्यागः, दानशीलं, वदान्यता. 2 उदारात्मता, महात्मता, माहात्म्यं.

Genesis, *s.* उत्पत्ति *f.*, आदि *m*

Genial, *a.* सुखप्रद, आनंदद, सुखावह, रम्य, रमणीय, मनोहर-रम, रुचिर, प्रसन्न, सुखकर (री *f.*), उत्साहवर्धक, जीवद. 2 प्रसवकारिन्, जनक. 3 प्रसन्नचित्त, सोल्लास, उदार. -ly, *adv.* प्रसन्नं, सानंदं, सहर्षं, सोल्लासं, प्रफुल्लं. -ness, *s.* रम्यता, उल्लासः, प्रसादः, प्रसन्नता.

Geniculated, *a.* ग्रंथिल

Genie, *s.* भूतः, पिशाचः.

Genital, *a.* जननसंबंधिन्, जनन in comp.; 'g. organ' जननेंद्रियं, उपस्थः, योनि *f.*, शिश्नं.

Genitive, *s.* षष्ठी विभक्तिः.

Genitor, *See* **Generator.**

Genius, *s.* धीशक्ति *f.*, मति *f.*, बुद्धि *f.*, धीः, मति-बुद्धि-प्रभावः-सामर्थ्यं, मतिप्रकर्षः. 2 धीसंपन्नः, धीमत् *m.*, धीशक्तियुतः, गुणवत् *m.* 3 कल्पना-निर्माण-शक्तिः. 4 प्रकृति *f.*, स्वभावः, शीलं. 5 लक्षणं, विशेषचिह्नं, वृत्ति *f.*, स्वधर्मः. 6 भूतः, पिशाचः, वेतालः; *See* **Demon;** 'dramatic g' नाट्यशक्तिः-कल्पना; 'good g.' सुदैवं; 'evil g.' दुर्दैवं.

Genteel, *a.* विनीत, दक्षिण, सभ्य, सुजन, सुशील, आर्य, आर्य-साधु-वृत्त, शिष्टाचार, आर्यचरित, सदाचार. 2 कुलीन, अभिजात, कुलोत्पन्न. 3 चारु, ललित, सुभग. -ly, *adv.* आर्यवत्, सुजनवत्. -ness, -Gentility, *s.* विनयः, दाक्षिण्यं, आर्यता, सौजन्यं, सुशीलता, सभ्यता, साधुता. 2 आभिजात्यं, कुलोत्कर्षः. 3 लालित्यं, चारुता.

Gentian, *s.* किरातः, चिर(रा)तिक्तः, भूनिंबः, हिमकः, किराततिक्तः, अनार्यतिक्तः.

Gentile, *a.*, *s.* अन्य-भिन्न-देशीय, देवार्चक. 2 सगोत्र, गोत्रज, ज्ञातीय.

Gentle, *a.* भद्र, कल्याण (णी *f.*), शिव, सुख. 2 कोमल, मृदु, मसृण, अपरुष, सुकुमार, अचंड, मृदुल, मंद, सौम्य; 'a g. laugh' मंदस्मितं, ईषद्धासः; 'g. breeze' मंदानिलः, मृदुपवनः; 'g. means' सामोपचारः, सामन् *n.*, मृदूपायः; 'g. words' प्रिय-मृदु-वचनं. 3 महाकुल, कुलीन, अभिजात, सुजन्मन्, साधु-आर्य-वंशज, कुल in comp.; 'a girl of g. blood' कुलकन्यका कुलप्रसूता. 4 (In addressing) अयि, भद्र, सौम्य, आर्य; 'g. lightning' अयि विद्युत्; 'g. folk' आर्यमिश्राः, आर्याः, साधुजनाः. 5 शांत, दांत. -ness, *s.* मृदुता, कोमलता, सौम्यता, सौकुमार्यं, मंदता; 'g. of manners' आचारसौजन्यं, आर्यवृत्तिः. -Gently, *adv.* मृदु, मंदं, अजातव्यथं, यथासुखं; 'shall rub g.' यथासुखं संवाहयामि (S. 3). 2 मंदं मंदं, शनैः शनैः, शनैः, अपरुषं, अचंडं. 3 निभृतं, अलक्षितं, मंदं -**Gentleman,** *s.* आर्यः, सुजनः, साधुजनः, आर्यवृत्तः, कुलीनः; सुविनीतः, महाजनः, आर्य-कुलीन-जनः, भद्रः, महानुभावः; oft. by श्री in comp. -like, -ly, *a.* सभ्य, विनीत, शिष्ट, सुशील, आर्य; 'g. manner' आर्यवृत्तिः, सौजन्यं; 'in a g. manner' नागरिकवृत्त्या (S. 5).

Gentry, *s.* विशिष्टजनाः, आर्याः, आर्यलोकाः-जनाः, कुलीनवर्गः-जनाः, सुजनता.

Genuflect, *v. i.* जानुं नम् c. -ion, *s.* जानुभ्यां आनतिः *f.*, जानुनतिः.

Genuine, *a.* अकृतक, अकृत्रिम, अकाल्पित, निर्व्याज, निर्व्यलीक, अकपट, निष्कपट, अवितथ, सत्य, यथार्थ. -ly, *adv.* सत्यं, निष्कपटं, निर्व्याजं. -ness, *s.* सत्यता, यथार्थता, निर्व्याजत्वं, अकृत्रिमता.

Genus, *s.* जाति *f.*, गणः, वर्गः.

Geography, *s.* भूगोलविद्या-शास्त्रं, भूपृष्ठविद्या. -er, *s.* भूगोलशास्त्रज्ञः, भूपृष्ठविद्याज्ञः. -ical, *a.* भूगोलशास्त्रविषयक.

Geology, *s.* भूतत्त्वं, भूगर्भशास्त्रं, भूतत्त्वविद्या. -ical, *a.* भूतत्त्वविषयक. -ist, *s.* भूतत्त्वज्ञः.

Geometry, *s.* ज्यामिति *f.*, रेखागणना-गणितं, भूमितिः. -ic, -ical, *a.* (*s.*) in comp.; 'g. proof' रेखागणितेन उपपत्तिः. -ician, *s.* भूमितिज्ञः.

Georgic, *s.* कृषि-कार्य-गीतं.

Germ, *s.* अंकुरः, अभिनवोद्भिद् *m.* 2 बीजं, मूलं, योनि *f.*, आदिः, प्रभवः, बीजकारणं. -**Germinate,** *v. i.* उद्भिद् pass., प्ररुह् 1 P, स्फुट् 6 P, विकस् 1 P. -ing, *a.* उद्भिद्-द्-ज्ज, अंकुरित -ion, *s.* उद्भेदः, स्फुटनं.

Germane, *a.* सनाभि, संपर्किन्, संपृक्त.

Gestation, *s.* गर्भ-धारणं-वहनं-पोषणं; गर्भिणीभावः.

Gesticulate, *v. i.* अंगानि विक्षिप् 6 P or संचल् c. -*v. t.* अभि-नी 1 P, नि-,रूप् 10, सूच् 10, नट् 10: *See* **Act.** -ion, *s.* अभिनयः; अंगविक्षेपः, चेष्टा, सूचना, अंगहारः, हावः, संकेतसूचनं. -or, *s.* अंगविक्षेपकः.

Gesture, *s.* चेष्टा, व्यापारः, इंगितं, भावः, अभिनयः, विलासः, विभ्रमः, अंगविक्षेपः, हावः; हस्तादिचालनं

Get, *v. t.* लभ् 1 A, आप् 5 P, अर्ज् 1 P or c., आ-समा-सद् c., विद् 6 U, प्रति-आ-पद् 4 A, अश् 5 A, अधिगम् 1 P, ग्रह् 9 U, आ-दा 3 A. **2** (To be produced) जन् 4 A, उत्पद् 4 A, सं-उद्-भू 1 P, प्र-सू 2, 4 A, (with genitive of person); 'I have got a pain in my teeth' दंतपीडा मे उत्पन्ना-जाता. **3** भू 1 P, 10, भृ 3 U; धा 3 U; 'I have got that book with me' तत्पुस्तकं मत्सकाशे वर्तते; *See* **Bear** also. **4** (Cause) ex. by causal; 'g. it done by him', तं तत्कारय; oft. by अनुनी 1 P, प्रोत्सह् c., प्रवृत् c.; 'g. ahead' अग्रेसरीभू. 'g. clear of' मुच् pass.; 'g. rid of' आत्मानं मुच् c., (with abl.) by निर् in comp.; 'g. abroad' प्रसृ-प्रसृप्- 1 P. बहुलीभू 1 P: *See* under **Abroad.** **-among,** मध्ये प्रविश् 6 P or गम्. **-at.** प्राप्, आगम्, आ-या 2 P, उप-स्था 1 U. **-away,** अपसृ 1 P, अप-इ 2 P, अपक्रम् 1 U, 4 P; चल् 1 P. अप-या गम्; 'g. away, you fool' अपेहि रे मूर्ख. **-back,** प्रतिलभ्, प्रत्या-दा, &c. **-beyond,** तॄ 1 P, अति-इ, अतिक्रम्. **-down,** अवतॄ, अवरुह् 1 P, अधो गम्, नि-अव-पत् 1 P, (*v. t.*) अवतॄ c., अवरुह् c.. &c. **-in,** प्रविश् 6 P. **-into,** पतत्; संकटे पतितः 'got into troubles'; आरुह् 1 P (a car &c.); 'he got into debt' ऋणग्रस्तो बभूव; 'g. ing into deep mud' पंकपूरमासाद्य. **-off,** (*v. i.*) निः-सृ, निर्गम्, अप-या, अप-क्रम्, निस्तॄ. **2** अवतॄ, अवरुह्; (*v. t.*) निरस् 4 U, अप-नी 1 P. **-on,** प्रवृत् 1 A, प्रचल्, प्र-सृ; 'they long got on well' चिरं ते सुखेन अवर्तंत or कालं निन्युः. **-out,** निर्गम्, अप-इ, निः-सृ. **2** त्यज् 1 P, मुच् 6 P; 'g. out of bed now' अधुना मुंच शय्यां. **-over, -through,** संतॄ; पारं-अंतं-गम्, अतिक्रम्, निस्तॄ, तीर् 10; आरुह्. **2** समाप् c.; *See* **Complete.** **-together,** संचि 5 U; समा-नी, संग्रह्; *See* **Collect.** **-up,** उत्-स्था; प्रबुध् 4 A, शयनं त्यज् 1 P or मुच्; (*v. t.*) सज्जीकृ 8 U, विरच् 10; उपकल्प् c. **-upon,** अधि-आ-रुह्. **-ter,** *s.* प्रापकः, लब्धृ *m.*, अर्जकः. **-ting,** *s.* लाभः, अवाप्ति *f.*, अर्जनं, अधिगमः-मनं, आगमः, आसादनं.

Gewgaw, *s.* क्रीडनकं, अल्पमूल्यं द्रव्यं or आभरणं. **-a.** निःसार, बहिरेव मनोहर.

Geyser, *s.* उष्णोदक-निर्झरः-स्रोतस् *n.*

Ghastly, *a.* प्रेत-शव-तुल्य, विवर्ण, शवसरूप-सवर्ण. **2** कराल, विकट, भीम, उग्र, दारुण, भयानक, भीमदर्शन, करालवदन, घोराकृति. **-ness,** *s.* प्रेतसादृश्यं, वैवर्ण्यं, विकटत्वं, दारुणत्वं.

Ghee, *s.* घृतं, आज्यं, हविस् *n.*, सर्पिस् *n.*, तन्नूनर्प.

Ghost, *s.* भूतः, पिशाचः, वेतालः, निशाचरः, प्रेतनरः. **2** आत्मन् *m.*; 'give up the g.' मृ 6 A; *See* **Die.** **-like,** *a.* प्रेत-भूत-सरूप, प्रेततुल्य. **-ly,** *a.* भूतविषयक-संबंधिन्. **2** पारत्रिक (की *f.*), आत्मविषय, पारमार्थिक (की *f.*).

Giant, *s.* महापुरुषः, विकटविग्रहः, बृहच्छरीरः, भीमविग्रहः, बृहत्कायः, अतिशक्त्युपेतः, राक्षसः. **2** दैत्यः, दानवः; *See* **Demon.** **-a.,** **-like,** *a.* अतिस्थूल, प्रकांडदेह, स्थूलप्रमाण, अतिमहत्, बृहत्काय, महाशरीर, विकट. **-ess,** *s.* राक्षसी, बृहच्छरीरा. **-Gigantic,** *a.* अतिमानुष (षी *f.*), राक्षसपरिमाण, भीमविग्रह, अतिमहत्-बृहत्, स्थूलकाय, विकट.

Gibber, *v. i.* *See* **Babble.** **-ish,** *s.* असंबद्धवचनं, प्रलापः, प्रजल्पितं, मृषार्थक वाक्य. **-a.** मृषार्थकं, अनर्थकं.

Gibbet, *s.* वध्यकाष्ठं-शिला, वध-घात-स्थानं. **-v. t.** वधं आदिश् 6 P, उद्-बंध् 9 P.

Gibbous, *a.* न्युब्ज, वक्र, आभोगवत्, बिंबाकार.

Gibe, *See* **Abuse.**

Giddy, *a.* भ्रमिन्, भ्रामररोगिन्, विभ्रांत, भ्रमणशील; better ex. by भ्रम् 1, 4 P. **2** भ्रमकारिन्, मत्त, उन्मादिन्. **3** (Fig.) चपल, चंचल, लोल, अस्थिर; *See* **Fickle.** **4** उद्धत, उन्मत्त, उत्सिक्त, गर्वित. **-ly,** *adv.* अविचार्य, लौल्यात्, चापल्येन. **-ness,** *s.* भ्र(भ्रा)मरं, भ्रमः-मि *f.*, घूर्णनं, घूर्णि *f.* **2** चापल्यं, लौल्यं, अस्थैर्यं, &c.

Gift, *See* under **Give.**

Gig, *s.* भ्रमरं. **2** लघुयानं-रथः. **3** क्षुद्र-लघु-नौका.

Giggle, *v. i.* मूर्खवत् हस् 1 P.

Gild, *v. t.* स्वर्णेन रंज् c., हेमरसेन-द्रवेण लिप् 6 P, सुवर्णयति (D.); बाह्यतेजसा रंज् c. **2** प्रकाश् c., विद्युत् c., विराज् c. **-ing,** *s.* स्वर्णरंजनं, स्वर्णच्छदः.

-ed,-Gilt, *a.* सुवर्णित, हेमरसखचित, स्वर्णमंडित, स्वर्णप्रतिबद्ध. **2** रंजित, विराजित.

Gill, *s.* श्वासेंद्रियं, अधोगंडः.

Gimcrack, *s.* क्रीडनकं, क्रीडावस्तु *n.*

Gimlet, *s.* वेधनिका, आस्फोटनी.

Gin, *s.* **Liquor,** q. v. **2** पाशः, उन्माथः, कूटयंत्रं, बंधनं, वागुरा.

Ginger, *s.* आर्द्रकं, शृंगवेरं, गुल्ममूलं; 'dry g.' शुंठि-ठी *f.*, विश्वं-श्वा *f.*, नागरं, विश्वभेषजं, महौषधं; 'g. beer or wine' आर्द्रकासवं-आर्द्रकमद्यं-पानं; 'g.-bread' आर्द्रकपिष्टक

Gingerly, *adv.* असाहसा, सावधानं, शनैः.

Gingle, *See* **Jingle.**

Gipsy, *s.* यक्षिणी, विमश्रिका, ईक्षणिका.

Giraffe, *s.* चित्रोष्ट्रः.

Gird, *v. t.* परि-अधि-वेष्ट c., परि-वृ 5 U or c. **2** आ-बंध् 9 P, परि-धा 3 U, सं-पि-नह् 4 P; 'g. round the body' शरीरं मह् or आ-च्छद् 10, परि-बंध् or परि-धा; 'g. up one's loins' परिकरं बंध्; 'girt by the (golden) lightning, as by a yellow garb' विद्युत्प्रभारचितपीतपटोत्तरीयः (Mr. 5). —*s. See* **Cramp. —ed, —Girt,** *a.* बद्ध, आनद्ध, परिवेष्टित, परिवृत; वलय-मेखला-रसना in comp.; 'sea-g. earth' समुद्र-रसना-उदधिवलया-पृथ्वी.

Girdle, *s.* मेखला, रश(स)ना, कांचि-ची *f.*, सप्तकी, सारसनं (of women); कटिसूत्रं, कटिवलयं, कक्ष्या-क्षा, परिकरः, कटिबंधनी, शृंखलः-ला-लं (of men). **2** वेष्टनं, परि-आ-वेष्टनं, मंडलं, वलयः-यं, चक्रवालं., **3** राशिचक्रं. —*v. t.* परि-वेष्ट c., परि-वृ 5 U, मेखलया बंध् 9 P, *See* **Gird.**

Girl, *s.* कन्या, बाला, बालिका, कुमारी, दारिका, वासूः, *See* **Daughter** also; 'one born from a g.' कानीनः, कन्यकाजातः. **—hood,** *s.* बालभावः, बाल्यं, कुमारीत्वं. **—ish,** *s.* कन्यानुरूप, बालेय.

Girth, *s.* वरत्रा, नध्री, वध्री; दू(चू)ष्या, कक्षा-क्ष्या.

Gist, *s.* फलितार्थः, निष्कर्षः, भावः, फलितं, परमार्थः, पिंडितार्थः.

Give, *v. t.* दा 1 P, 3 U, ऋ c. (अर्पयति), प्रतिपद् c., दद् 1 A, विश्रण् 10, उत्-वि-सृज् 6 P, (with dat. of person); निक्षिप् 6 P, संक्रम् c. (with loc.); त्यज् 1 P, दिश् 6 P. **2** (Produce) ex by भू 1 P, संपद् 4 A, जन् 4 A; '3 repeated 2 times g. 6' द्विरावृत्तास्त्रयः षड् भवंति-संपद्यंते 'g. chase' अनुसृ-अनुधाव् 1 P; 'g. ear' अव-धा 3 U, कर्णं दा, श्रु 5 P; 'g. ground' अपक्रम् 1 U, 4 P; अपसृ, परा-नि-वृत् 1 A; त्यक्त्वा गम् 1 P; 'g. one's self up to' सेव् 1 A, भज् 1 A; आसंज् pass., आसक्त-निरत-निविष्ट-*a.* भू, (with loc.); 'g. offence' अपराध् 4, 5 P, विप्रियं-प्रतिकूलं-कृ 8 U or आचर् 1 P; 'g. utterance' उदीर् 10, उच्चर् c., उदाहृ 1 P. **—away,** (in marriage) प्रतिपद् c., उत्सृज्, प्र-दा. **2** विश्रण्, दानेन क्षै c. (क्षपयति). **—back,** प्रतिदा, प्रति-ऋ c., निर्यत् 10. **—forth,** प्रथ् 10, प्रकाश् c., निविद् c., ख्या c. (ख्यापयति). **—in,** अनुमन् 4 A, अनुरुध् 1 A; स्वाग्रहं त्यज्. **—off, Abandon,** q. v. **—out,** निविद् c., प्रकाश् c, घुष् 10, प्रख्या c. **2** सृज् 6 P, विसृज्, उद्वम् 1 P उद्-गॄ 6 P, निःसृ c. **—over,** त्यज्, उत्सृज्, निवृत् 1 A, विरम् 1 P, (with abl.). **2** असाध्य *a.* इति मत्वा त्यज्; आशां त्यज्; (*v. i.*) शम् 4 P, पत् 1 P; 'when the winds g. over' शांते पवने. **—up,** त्यज्, हा 3 P, उत्-वि-सृज्. **2** निवृत्, विरम्; 'g. up for lost' नष्टमाय *a.* मन् 4 A. **—way,** शम् 4 P, निवृत्, विरम्, शिथिलीभू. **2** भंज् pass., अवसद् 1 P; 'the cord gave way' रज्जुर्भग्ना; 'the wall gave way' भित्तिरवसन्ना. **3** अव(प)सृ, अप-इ, मार्गं दा or त्यज्, अपक्रम्, अप-या. **4** वशं गम्-इ-या, अधीन-वश-आयत्त *a.* भू; 'do not g. way to grief' दुःखो वशं मा गमः, शोकाधीनो मा भूः, वैक्लव्यं मावलंबस्व. **—er,** *s.* दातृ *m.*, त्यागिन् *m.*; gen. ex. by दायक, द, प्रद, दायिन्, in comp.; 'g. of milk' पयोदायिनी, दुग्धप्रदा, &c. **—ing,** *s.* दानं, विसर्जनं, उत्सर्गः, त्यागः, वितरणं, अर्पणं, प्रतिपादनं, विश्राणनं. **—Gift,** *s.* दानं, प्रतिपादनं; *See* above. **2** दानं, उपहारः, उपायनं, उपदा, प्रीतिदानं, प्राभृतं, प्रदेशनं, उपग्राह्यं; 'one deserving a g.' दाक्षिणीय, दक्षिणार्ह, दक्षिण्य; 'marriage-g.' यौतकं, सुदायः. **3** गुणः, शक्ति *f.* **—ed,** *a.* उपेत, सं-उप-पन्न, विशिष्ट, युक्त, अन्वित, शालिन् in comp. **2** गुणोपेत, गुणसंपन्न, गुणिन्, गुणवत्.

Glacial, *a.* हिमरूप, हैम (मी *f.*), हिम.

Glacier, *s.* हिमानी, हिमसंहति *f.*

Glacis, *s.* प्रवण निम्न-भूमि *f.*

Glad, *a.* प्र-,सं-,हृष्ट, आनंदित, प्रीत, सानंद, प्रमुदित, तृप्त, सोल्लास, उल्लसित, प्रसन्न. **2** हर्षजनक, हर्ष-आनंद-कर (री *f.*); नंदक, रमणीय, प्रमोदिन्; 'I am g.' हंत, दिष्ट्या. **—den,** *v. t.* आ,नंद् c., प्री 9 P, 10; *See* **Delight. —dening,** *a.* हर्षद, प्रीतिप्रद, हर्षकर, प्रमोदिन्. **—ly,** *adv.* सहर्षं, सानंदं, सप्रमोदं, हृष्टमनसा, संतोषेण, प्रीत्या, साह्लादं. **—ness,** *s.* हर्षः, प्रमोदः, आह्लादः, संतोषः, प्रीति *f.*, उल्लासः, चित्तप्रसादः, तुष्टि *f.* **—some,** *See* (*a.*).

Glade, *s.* वन-गुल्मः-पथः-मार्गः, तरुगहनमार्गः.

Gladiator, *s.* असिक्रीडकः, आसिकः, मल्लः. **—Gladiature,** असिक्रीडा-युद्धं.

Glair, *s.* अंडशुक्लं.

Glamour, *a.* *See* 'Enchantment.'

Glance, *s.* दृष्टिपातः, ईक्षणं, वीक्षितं, नयनपातः-विक्षेपः, दृक्पातः, आलोकितं; 'side-long g.' नयनोपांतविलोकितं, साचिविलोकितं, अपांग-दर्शनं-दृष्टि *f.*, कटाक्षः; 'at the very first g.' सकृद्दृष्टिपातेन, प्रथममेव; 'good at the first g.' आपातमात्रे रमणीय, आपातरमणीय. **2** अर्धवीक्षणं,

ईषद्दृष्टिः. 3 स्फुरितं, स्फुरणं, द्युति *f.* –*v. i.* दृष्टिं क्षिप् 6 P, चक्षुः-दृष्टिं *f.*-दा 3U or पत् c. (with loc.); 'g.-ing at the antelope' कृष्णसारे ददच्चक्षुः (S. 1). 2 लघु निर्घृष् 1 P, लघु हत्वा अति-इ 2 P. 3 (जवेन) परिस्फुर् 6 P or विलस् 1 P. **–ingly,** *adv.* लघु, ईषत्, अल्पमात्रं, स्तोकं. 2 दृक्पातेन, तिर्यक्, साचि, कटाक्षेण.

Gland, *s* अधिमांसं, मांसपिंडः, पिंडः.

Glanders, *s.* क्षयथुः.

Glare, *s.* तेजस् *n.*, दीप्ति *f.*, द्युति *f.*, प्रखर-अति-तेजः, अतिप्रभा-द्युतिः-दीप्तिः, नेत्रप्रतिघातिनी प्रभा. 2 उग्रदृष्टि *f.*, क्रोधदृष्टिः. –*v. i.* संदीप् 4 A, प्रद्युत् 1 A, उज्ज्वल् 1 P, अतितेजसा स्फुर् 6 P or दृष्टिं प्रतिहन् 2 P or संतप् c.; दीप् freq. (देदीप्यते). 2 उग्रदृष्टिं पत् c., कोपेन दृश् 1 P or ईक्ष् 1 A. **–ing,** *a.* संदीप्त, उज्ज्वल, अतिभास्वत्, देदीप्यमान. 2 सुस्पष्ट, सुप्रकाश, प्रत्यक्ष, पुरःस्फुरत्. **–ingly,** *adv.* सुस्पष्टं, सुप्रकाशं.

Glass, *s.* काचः, स्फटिकः, क्षारः. 2 (Cup) चषकः-कं, काचपात्रं-भाजनं. 3 आदर्शः, दर्पणः, मुकुरः. –*a.* काचमय (यी *f.*), काचनिर्मित, काच in comp.; 'g.-blower' काचधमकः; 'g.-grinder' काचपरिष्कारकः; 'g. house,' काचनिर्माणशाला-स्थानं; 'g.-man' काचविक्रयिन् *m.*; 'g.-work' काचनिर्माणं-कर्मन् *n.* **–like,** *a.* काचोपम, काचतुल्य. **–y,** *a.* स्फटिकोपम, काचवत्स्वच्छ, काचविमल, स्फटिकप्रभ, स्फाटिक (की *f.*), सुप्रसन्न. 2 श्लक्ष्ण, स्निग्ध. **–Glaze,** *v. t.* काचयति (D.), काचेन आच्छद् 10. 2 श्लक्ष्णीकृ 8 U, स्निग्धीकृ, श्लक्ष्णयति (D.), –*s.* स्निग्धता, श्लक्ष्णता, **–Glazier,** *a* काचसंधातृ *m.*, काचबंधकः.

Glaucous, *a.* घनश्याम, मेघनील, समुद्रवर्ण.

Glaze, *v. t. See* under **Glass.**

Gleam, *v. i* परि-,स्फुर् 6 P, विलस् 1 P, क्षणमात्रं प्रकाश् 1 A or उज्ज्वल् 1 P; *See* **Shine** also. –*s.* प्रभा, कांति *f.*, तेजस् *n.*, औज्ज्वल्यं. 2 स्फुरणं, स्फुरितं, क्षणप्रभा-कांतिः, अचिरप्रभा, क्षणज्योतिस् *n.* 3 रश्मिः, करः, किरणः, अंशुः; 'not a g. of hope' न आशालवोऽपि. **–y,** *a.* क्षण-अचिर-प्रभ, चलद्युति, कंपितप्रभ, क्षणद्योतिन्.

Glean, *v. t* (bits &c.) उंछ् 6 P, शिल् 6 P, उद्-ग्रस् 9 P or c., अवशेषं चि 5 U or संग्रह् 9 P. 2 संकल् 10 संग्रह्, उद्धृ 1 P. –*s.* धान्यशेषः, शेषधान्यसंचयः. **–er,** *s.* उंछशीलः-वृत्तिः, उंछनकृत् *m.* 2 संग्रहीतृ *m.* **–ing,** *s.* उंछः, शिलं, उंछशिलं, ऋतं. 2 संग्रहः, संकलनं, उद्धारः.

Glebe, *s.* मृद् *f.*, मृत्तिका; स्थलं-ली, भूमि *f.*

Glee, *See* **Delight.**

Gleet, *s.* इक्षु-मधु-मेहः, मेहविकारः.

Glen, *s.* दरी, कंदरः-रा; अद्रिद्रोणी, उपत्यका.

Glib, *a.* वाक्चपल, त्वरित-द्रुत-वाच्; चपल, लोल. 2 पिच्छिल, मसृण, स्निग्ध, श्लक्ष्ण, चिक्कण. –*v. t* **Castrate,** q. v. 2 श्लक्ष्णीकृ 8 U. **–ly,** *adv* चपलतया, वाक्चापल्येन. 2 श्लक्ष्णं. **–ness,** *s.* वाक्चापल्यं, चापल्यं. 2 श्लक्ष्णता, मसृणता.

Glide, *v. t.* सृप् 1 P, सं-वि-प्र°, प्र-वि-स्रु 1 P; मंदं इ-या 2 P or गम् 1 P, शनैः प्रसृ or चल् 1 P: अलक्षितं-निभृतं गम् or या or अति-इ; *See* **Steal.** 2 वह् 1 P, स्रु 1 P; स्यंद् 1 A, री 4 A. **–ing,** *s.* संसर्पः-र्पणं, सरणं, निस्यंदः-दनं.

Glimmer, *v. i.* मंदं मंदं ज्वल् 1 P or दीप् 4 A; मंदप्रभया-अचिरप्रभया प्रकाश् 1 A or द्युत् 1 A or स्फुर् 6 P. –*s.*, **Glim,** *s.* मंदप्रभा-तेजस् *n.*, मंद-अचिर-द्युति *f.*, -दीप्ति *f.*, स्फुरणं, स्फुरितं. **–ing,** *a.* मंदप्रभ द्युति, तेजस्, ईषत्स्फुरित, पांडुद्युति-किरण, मंदच्छाय. 2 मंद, असुप्रकाश, अव्यक्त, अस्पष्ट.

Glimpse, *s.* क्षण-मुहूर्त-दर्शनं; ईषद्दृष्टि *f.*, अर्धवीक्षणं, अल्पो दृक्पातः. 2 क्षण-अचिर-प्रभा; *See* **Gleam.**

Glint, *v. i.* प्रकाश् 1 A. –*v. t.* द्युत् c.

Glisten, Glister, *v. i.* स्फुर् 6 P, प्रकाश् 1 A, द्युत् 1 A. **–ing,** *a.* मसृण, चिक्कण, श्लक्ष्ण, स्निग्ध.

Glitter, *v. i.* द्युत्-प्रकाश् 1 A; भास् 1 A, भा 2 P; स्फुर् 6 P, *See* **Shine.** –*s.* दीप्ति-द्युति-रुचि-कांति-*f.*, प्रभा, तेजस् *n.*; ज्योतिस् *n.*, वर्चस् *n*, आभा. **–ing,** *a.* प्रभावत्, उज्ज्वल, भासमान, विद्योतिन्, भासुर.

Gloaming, *s.* संध्या; संध्यासमयः.

Gloat, *v. i.* संतृप् 4 P, संतुष् 4 P: आत्मानं संतृप् c. or संतुष् c., लोभाद् निरीक्ष् 1 A or निर्वर्ण् 10.

Globe, *s.* गोलः-लं; वर्तुलः-लं; मंडलं; चक्रं. 2 भूमंडलं, भूगोलः, क्षितिमंडलं-तलं. **–Globate, -Globular,** *a.* वर्तुल, गोलाकार, गोलाकृति, वृत्त, निस्तल, मंडलाकार, गोल. **–ly,** *adv.* मंडलरूपेण, मंडलवत्, गोलाकारेण. **–Globule,** *s.* बिंदुः, लघुगोलः, गोलकः.

Glomerate, *v. t.* मंडलीकृ 8 U, गोलीकृ, पिंडीकृ.

Gloom, *s.* अंधकारः, तमस् *n.*, तमिस्रं-स्रा, तिमिरं, ध्वांतं; अवतमसं, ईषत्तमः (partial g). 2 निष्प्रभत्वं, विषादः, छाया. –*v. t.* **Darken,** q. v. **–Gloomy,** *a.* सतिमिर, तमोवृत, सांधकार, तिमिरावगुंठित. 2 दुर्दर्शन, मलिनप्रभ, अप्रभ, निष्प्रभ, निरालोक, मलिन. 3 विषण्ण, दीन, अवसन्न, सविषाद, निरानंद, म्लान, खिन्न, उद्विग्न. **–ly** *adv.* निष्प्रभं, सांधकारं. 2 सविषादं, सखेदं, सोद्वेगं. **–ness,** *s.* निष्प्रभत्वं, &c. 2 विषादः, दैन्यं, अवसादः, चित्तोद्वेगः, खेदः, म्लानता, उद्वेगः.

Glory, *s.* कीर्ति *f.*, यशस् *n.*, ख्याति *f.*, विश्रुति *f.* महिमन् *m.*, प्रतापः, ओजस्विता. **2** श्रीः, तेजस् *n.* शोभा, द्युति *f.*; 'g. of youth' यौवनश्रीः. **3** माहात्म्यं, गौरवं, प्रतिष्ठा, पूजा, मानः. **4** प्रशंसा, स्तुति *f.*, श्लाघा, स्तवः, स्तुतिवाक्यं **5** रत्नं, अवतंसः, तिलकः, ललामं. **6 Absolution,** q. v.; 'vain g' अहंकारः, विकत्थनं-ना, दर्पः, गर्वः, आत्मश्लाघा; 'g. to you, Oh king' जयतु जयतु देवः; 'g. of victory' जयोदाहरणं. —*v. i.* अत्यंतं प्रमुद् 1 A or आनंद् 1 P, उल्लस् 1 P; 'you g. in disobeying your father' पितुरवज्ञानं आत्मगौरवं मन्यसे. **2** विकत्थ् 1 A, दृप् 4 P, आत्मानं श्लाघ् 1 A; 'I do g. in that name' तन्नामधारी कृतिनमात्मानं मन्ये खलु. —**Glorify,** *v. t.* उत्-सं-कृत् 10, प्रशंस् 1 P, श्लाघ्, स्तु 2 U; गुणान् वर्ण् 10 or कृत् or प्रकाश् c., कीर्तिं गै 1 P. **2** स्वर्गं आरुह् c., परमपदं प्राप् c. **-ication,** *s.* गुणवर्णनं-ना, प्रशंसा, स्तुतिवादः, गुणकीर्तनं, यशःख्यापनं. —**Glorious,** *a.* यशस्वत्, कीर्तिमत्, महायशस्, प्रथित, विश्रुत, ख्यात, यशस्विन्, उदग्रयशस्. **2** कीर्तिकर-यशस्कर (री *f.*), श्लाघावह, प्रशस्य. **3** तेजस्विन्, महत्, महोज्ज्वल, श्रीमत्, प्रतापवत्, महोदय, अतिशोभन, ओजस्विन्, सुप्रभ, वर्चस्विन्. **4** विशिष्ट, परम, उत्तम, उत्कृष्ट, प्रशस्ततम, श्रेष्ठ. **-ly,** *adv.* सप्रतापं, कीर्तियुक्त, परमं, उत्कृष्टं.

Gloss, *s.* टीका, टिप्पनी, भाष्यं, व्याख्यानं, वृत्ति *f.*, विवरण. **2** बाह्यशोभा-कांति-रुचि *f.*, बहिराभा, कृत्रिमच्छवि *f.*, कल्पितशोभा. —*v. t.* टीकया व्या-ख्या 2 P or वि-वृ 5 U; भाष्यं लिख् 6 P. **2** बाह्यतः शुभ् c.; स्निग्धी-मसृणी-कृ 8 U; बाह्यशोभां दा 3 U or उत्पद् c. **-y,** *a.* स्निग्ध, चिक्कण, श्लक्ष्ण, मसृण. **2** बाह्यप्रभ, बाह्यतः शोभित, आपातरुचिर, बहीरमणीय.

Glossary, *s.* कोशः-षः. शब्दसंग्रहः-कोशः, निघंटुः, अभिधानं, समाम्नायः; पशुसमाम्नायः 'g. of words relating to beasts.' **-ist,** *s.* कोशलेखकः; संकलयितृ *m.*

Glottis, *s.* प्रति-अलि-उप-जिह्वा.

Glove, *s* करच्छदः, हस्तत्राणं-परिधानं, हस्ताच्छादनं.

Glow, *s.* तापः, आतपः, दाहः, उष्मन् *m.*, दीप्ति-द्युति *f*, तेजस् *n.*, उत्तापः. **2** रक्तता, रक्तिमन् *m.*, रागः, अरुणिमन् *m.* —*v. i.* दीप् 4 A, प्रकाश् 1 A, ज्वल् 1 P, तप् 1 P, 4 A, दह् pass.; अरुणीभू 1 P, रंज् pass., रक्तीभू; 'g. ing with rage' क्रोधेद्ध, रोषसंतप्त, प्रदीप्तक्रोध; ज्वलन्निव ब्रह्ममयेन तेजसा (K. v. 30) 'as if g. ing with Brahmanic lustre.' **-ing,** *a.* सं-,प्र-, दीप्त, ज्वलित, उत्तप्त, देदीप्यमान, उज्ज्वल, चंड; रक्त अरुण; 'in g. colours' उज्ज्वलरूपेण, हृदयहारितया, हृदयंगम, मनोरम; 'with g. eyes' दीप्ताक्ष *a.* **-ingly,** *adv.* तेजसा, उत्तापेन, चंडं, दीप्त्या. **-worm,** *s.* खद्योतः, ज्योतिरिंगणः, प्रभाकीटः

Glower, *v. t.* सभ्रूभंगं प्रेक्ष् 1 A.

Gloze, *See* **Flatter.**

Glue, *s.* संश्लेषणद्रव्यं, लेपः. —*v. t.* सं-धा 3 U, संश्लिष् c., संयुज् 7 U, 10, संलग्नीकृ 8 U. **-y,** *a.* श्यान, सांद्र, चिक्कण.

Glum, *a.* प्रतीप-वाम-वक्र-शील.

Glut, *v. t.* भक्ष् 10, ग्रस् 1 A, निगॄ 6 P, अतिमात्रं तृप् c, अत्यंतं पूर् 10, सौहित्यं जन् c. (जनयति). —*s.* अतितृप्ति *f.*, अतिसौहित्यं, निर्वेदः. **2** अतिरेकः, उद्रेकः. अतिबाहुल्यं, प्राचुर्यं.

Glutinate, *v t.* लेपेन संश्लिष् c or संयुज् 7 U, 10

Glutinous, *a.* श्यान, सांद्र, चिक्कण, स्निग्ध, संलग्नशील.

Glutton, *s.* औदरिकः, उदरंभरिः, घस्मरः, आद्यूनः, कुक्षिंभरिः, अत्याहारिन् *m.*: *See* below. **-ous,-ish,** *a.* औदरिक (की *f.*), अत्याहारिन्, बहुभोजिन्, अत्याहारप्रिय, भक्षक, घस्मर, अद्मर, आद्यून, कुक्षिंभरि, उदरंभरि, गृध्नु, लोलुप-भ, अतिलुब्ध, अतृप्त. **-ously,** *adv.* अत्याहारेण, लोलुपतया. **-y,** *s.* अत्याहारः, घस्मरता, गृध्नुता, जिह्वालौल्यं, अतृप्ति *f.*, औदरिकता.

Gnarl, *v. i.* गर्ज् 1 P.

Gnarled, *a.* ग्रंथिल, ग्रंथि-पर्व-विशिष्ट.

Gnash, *v. t.* (The teeth) दंतैर्दंतान् निष्पीड् 10 or निघट्ट् c. or घृष् 1 P, निष्पिष् 7 P, or सं-दंश् 1 P, क्ष्विड् 1 P. -i[illegible] दंतनिष्पेषः-घर्षण, क्ष्वेडनं.

Gnat, *s.* मशकः, दंशः, प्राचिका, वनमक्षिका.

Gnaw, *v. t.* दंश् 1 P, चर्व् 1 P or c., अल्पशः भक्ष् 10 or खाद् 1 P; चर्वणेन कृत् 6 P **-ing,** *s.* चर्वणं, दंशनं.

Gnome, *s.* सूक्तिः. **2** भूतः, पिशाचः.

Gnomon, *s.* शंकुः; कीलः-लकः.

Go, *v. i.* गम् 1 P, या-इ 2 P, व्रज् 1 P, चल्-चर् 1 P, पद् 4 A, ऋ 1, 3 P; सृ 1, 3 P; क्रम् 1 U, 4 P; (as water) वह् 1 P, स्रु 1 P, स्यंद् 1 A. **2** (Fare) वृत् 1 A, स्था 1 P; 'how g. es it with her' कस्तस्या वृत्तांतः. **3** (As prospective future) ex. by fut. part., मनः or काम with inf. or desid. forms; *See* **About;** 'g. astray' भ्रम् 1, 4 P; उत्पथं या, सन्मार्गात् च्यु 1 A or भ्रंश् 1 A, 4 P; उत्क्रम्, अति-व्यभि-चर्; 'g. on foot' पद्भ्यां व्रज्; 'g. on horse-back' अश्वेन संचर्; 'as the story g. es' किल,

'g. for nothing' (go to dogs) विफलीभू; 'g. to bed' शय्यां भज्-सेव् 1 A; 'she is far gone in love' दूरगतमन्मथा सा (S. 3), अतिभूमिं गतोस्या अनुरागः; 'g.- between' मध्यस्थः, मध्यपुरुषः; (female g.) शंभली, कुट्टिनी; सुरतदूती; 'g. by' निगमः, पलायनं, व्यपदेशः; 'g.-cart' क्रीडाशकटः. **-about.** परिगम्-इ &c. **2** यत् 1 A, उद्यम् 1 A, व्यव-सो 4 P, आरभ् 1 A, उपक्रम् 1 A. **3** अनुष्ठा, वि- धा 3 U, *See* **Execute. -away,** अप-इ-सृ-क्रम्-गम्-या-सृप्, प्र-इ, स्था 1 A. **-between,** मध्ये स्था or वृत्, अंतः-इ. **-by,** अति-इ, समीपतः गम्. **2** अनुगम्, अनुवृत्, अनुरुध् 4 A, अनु-सृ; 'he g.-es by the name of' इति ख्यातः or ज्ञातः; उमाख्यां सुमुखी जगाम (K. I. 26) 'went by the name of' &c. **-down,** अधो गम्. **2** अस्तं गम्-या; (*fig.*) नाशं-क्षयं-या; प्र-ली 4 A, ध्वंस् 1 A. **-forth,-forward,** निर्गम्, निःसृ-क्रम्, प्र-सृ, प्र-स्था, प्र-या. **-in,** प्र-आ-विश् 6 P, अंतर्गम्-या. **2** (for) समन् 4 A, उरी-अंगी-कृ 8 U, प्रति-पद् 4 A. **-off,** अपगम् &c. **2** प्र-इ, मृ 6 A; परलोकं या. **-on,** प्र-वृत्, प्रगम्-या-सृप्. **2** प्र-स्तु 2 U, प्रारभ् 1 A; 'g. on with your study' प्रवर्ततां-प्रस्तूयतां-अध्ययनं. **-out,** निर्गम्, निःसृ, &c., बहिर्गम्. **2** (Of light) निर्वा 2 P or c. pass.; शम् 4 P. **-over,** वच् c., अधि-इ 2 A: (to one's self) अनुवच् c. **2** परि-ईक्ष् 1 A. **3** आक्रम्, लंघ् 1 A, 10. **4** अन्यपक्षं सं-आ-श्रि 1 U: स्वपक्षात् भ्रंश् 1 A, 4 P. **-round,** परि-इ गम्; प्रदक्षिणीकृ. **-through,** अनुभू, उपागम्, वि-धा, अनु-ष्ठा, कृ, निर्वह् c.; सेव् 1 A, आचर्. **2** पारं गम्, समाप् c.: अव-सो 4 P. **3** प्र-निर्-विश्, नि-भिद् 7 P; भित्त्वा निर्गम्; व्यध् 4 P. **-to, up to,** उप-सृ-इ-गम्-या, उप-स्था, प्रति-पद् &c. **2** (*Interj.*) धिक्, अपेहि, अपसर. **-up,** उद्-इ, उत्पत्, ऊर्ध्वं गम्. **-er,** *s.* गामिन्-गंतृ *m.*, चरः, यायिन् *m.* in comp. **-ing,** *s.* गमनं, यानं, सरणं, चलनं, व्रजनं, गति *f.*, अयनं, &c.

Goad, *s.* अंकुशः, सृ(शृ)णि *f.* **—***v. t.* अंकुशेन तुद् 6 P or प्रचुद् 10. **2** प्रचुद्, प्रणुद् c., प्रोत्सह् c., प्रेर् c., प्रवृत् c., उद्युज् 10, उत्तिज् c.

Goal, *s.* अंतः, अंतस्थानं, अवधिः, अवसानभूमि *f.*; 'g. of ambition' आशावधिः. **2** आशयः, अभिप्रायः, उद्देशः.

Goat, *s.* अजः, छागः, छगलकः, बस्तः, छुभः; 'she-g.' अजा, छागी; 'g.-herd' अजाजीवः, जाबालः, अजपालः-लकः, छागपोषकः; 'a flock of g. s' आजकं. **-ish,** *a.* अजगंध.

Gobbet, *s.* कवलः, ग्रासः.

Gobble, *v. t.* सत्वरं ग्रस् 1 A or भक्ष् 10.

Goblet, *s.* चषकः-कं, पानपात्रं-भाजनं, कंसः-सं.

Goblin, *s.* भूतः, वेतालः, पिशाचः, राक्षसः, निशाचरः, रात्रि(त्रिं)चरः.

God, *s.* देवः, सुरः, अमरः, निर्जरः, विबुधः, सुपर्वन् *m.*, सुमनस् *m.* त्रिदिवेशः, दिवौकस् *m.*, आदितेयः, दिविषद् *m.*, लेखः, अदितिनंदनः, आदित्यः, ऋभुः, अस्वप्नः, अमर्त्यः, अमृतांधस् *m* बर्हिर्मुखः, क्रतुभुज् *m.*, गीर्वाणः, दानवारिः, वृंदारकः, दैवतः-तं; 'great g.' परमेश्वरः, परमात्मन्; *m.* 'god-dess' देवी, भगवती, सुरांगना, देवपत्नी; in comp. words ex. by धर्म; 'g.-father' धर्मपितृ *m*, so धर्ममातृ *f.* धर्मपुत्रः-त्री, धर्मकन्या-सुता, &c **-less,** *a.* निरीश्वर, नास्तिक, अनीश्वरवादिन्. **-lessness,** *s.* मिथ्यादृष्टि *f.*, नास्तिकता. **-like,** *a.* देवतुल्य-रूप, देवोपम, दिव्य. **-ly,** *a.* धार्मिक (की *f.*), धर्मनिष्ठ-परायण, पुण्यशील, पुण्यात्मन्, ईश्वरभक्त-पूजक. **-liness,** *s.* धर्मसेवा, पुण्यशीलता, ईश्वरभक्ति *f.*, श्रद्धा, &c. **-ship,** *s.* देवत्वं, देवभावः. **-Godsend,** *s.* ईश्वरप्रेरित *a.* द्रव्य, ईश्वरप्रसादः, सौभाग्यं, लक्ष्मीवृत्तं.

Goggle, *v. i.* नयने विक्षिप् 6 P or लुल् c.; 'g eye' लोलनयने; 'g.-eyed' लोलनयन, वक्र-तिर्यक्-दृष्टि.

Goitre, *s.* गड्डुः.

Gold, *s.* सुवर्णं, स्वर्णं, कनकं, कांचनं, हेमन् *n.*, चामीकरं, जातरूपं, हिरण्यं, हाटकं, तपनीयं, शातकुंभं, गांगेयं, भर्मन् *n.*, कर्बुरं, महारजतं, रुक्मं, कार्तस्वरं, जांबूनदं, अष्टापदः-दं; 'g. for ornaments' शृंगिः, शृंगकनकं; 'g.-beater or drawer' सुवर्णोद्वर्तनकृत् *m.*; 'g.-dust' कांचनभूः, कनकरागः; 'g.-smith' स्वर्ण-सुवर्ण-कारः, कलादः, नाडिंधमः, रुक्मकारकः; 'g.-thread' कनकसूत्रं. **—***a.*, **—en,** *a.* हैम (मी *f.*), सौवर्ण (र्णी *f.*), (*s.*) in comp., or by मय (यी *f.*) affixed to (*s.*).

Golf, *s.* कंदुकक्रीडा-लीला.

Gong, *s.* घनं, कांस्यं.

Gonorrhœa, *s.* शुक्रदोषः.

Good, *a.* भद्र, साधु, प्रशस्त, प्रशस्य, शुभ, कल्याण (णी *f.*), सत्, वर, शोभन, गुणवत्, निर्दोष; oft. by सु or सत् in comp. **2** धर्मशील, साधु-आर्य-वृत्त, सदाचार, सच्चरित, सुकृतिन्, पुण्य, पुण्यात्मन्, पुण्यशील, धार्मिक (की *f.*). **3** योग्य, उचित, युक्त, उपयुक्त, हित; gen. ex. by pot. pass. part. **4** सुजन, हितकाम, प्रियकारिन्, उपकारक, हित, प्रियकर. **5** अन्यून, अदूषित, अक्षत, संपूर्ण. **6** बहु, प्रचुर, महत्, अमल्प, भूरि, सु or अति pr.; 'a g. fellow' भद्रः, सौम्यः; 'my g. sir,' भद्र, सौम्य; 'g. quality' गुणः, स-

गुणः; 'g. wishes' आशिस् *f.*, आशीर्वादः-वचनं; 'g. and bad' शुभाशुभ; 'so g. as' अनुग्रह-पूर्वकं, कृपया; 'for g.' अत्यंतं, असन्निवृत्त्यै; 'a g. deal' भृशं, अतीव, सु or अति pr.; 'g. morning to you' शुभस्ते प्रभातकालः; 'it will be g. for you' तव कल्याणाय भवेत्, कल्याणभाव-हेतु; 'is g. unto weariness' आयासजनकमेव, श्रममात्रदायकं; g. for nothing' निरुपयोग, निर्गुण, निष्फल; 'as g. as' समं. -s. उपकारः, उपकृति *f.* 2 हितं, भूति *f.*, भद्रं, शुभं, कल्याणं, कुशलं, श्रेयस् *n.*, क्षेमं; oft. by अर्थं; 'for the g. of the people' प्रजार्थं, लोकहिताय, प्रजाभूतये, &c. 3 उपयोगः, लाभः, फलं; oft. ex by किं, अर्थं, अलं, with inst.; 'what is the g. of seeing her' किं तया दृष्टया (S. 2), कोऽर्थस्तस्या दर्शनेन; 'what g. do you get by weeping' अलं परिदेवनेन. 4 सुकृतं, पुण्यं, धर्मः, सुचरितं, साधुवृत्तं, सदाचारः; 'to do g.' उपकृ 8 U; हितं-कल्याणं-कृ; क्षेमं आवह् 1 P; 'g. and evil (bad)' शुभाशुभं, हिताहितं. -*interj.* साधु, सुष्ठु, सम्यक्, बाढं, कामं, भवतु, तथास्तु, तथेति; युज्यते, अनुमतं मम (V. 2). 'G.-breeding' साधुता, सौजन्यं, विनयः, सभ्यता, 'possessed of g.-breeding' सुशील, सुविनीत, सुजन, अभिजात; 'g.-conditioned' सुस्थ, सुस्थित; 'g. fortune or luck' *See* **Fortune**; 'g.-humour' सद्भावः, उल्लासः, चित्तप्रसादः, उल्लासवृत्ति *f.*, आनंदः, प्रमोदः; 'g.-nature' सद्भावः, सुस्वभावः, सौजन्यं, सुशीलता; सुप्रकृति *f.*; 'g.-humoured or g.-natured' हृष्टचित्त, प्रसन्नचित्त, सोल्लास, सानंद, सुस्वभाव, सुशील, सुप्रकृति, सुजन, सद्भाववत्, साधुशील, धर्मात्मन्, पुण्यात्मन्, सुहृदय; 'g.-looking' दर्शनीय, सुरूप, सुदर्शन, सुभग, प्रियदर्शन, प्रेक्षणीय, रम्याकार, सुवदन; 'g.-manners' विनयः, विनीतता, मर्यादा, सुनीति-रीति *f.*; सभ्यता, शिष्टाचारः, सुशीलता, सौजन्यं, सुसत्-चरित्रं, सदाचारः, साधुवृत्तं; 'g.-sense' विवेकः, ज्ञानं, प्रज्ञता, प्रबुद्धता, प्रबोधः. सौजन्यं, सद्भावः, सुशीलता; 'g.-will' हितेच्छा, हितकाम्या, प्रीति *f.*, प्रियता, अनुकूलता, भक्ति *f.*, अनुरागः. -**ly**, *a.* चारु, सुंदर (री *f.*), सुरूप, सुदृश्य, प्रेक्षणीय, लावण्यवत्, रम्य, रमणीय, मनोरम-हर, रुचिर. 2 अनल्प, महत्, प्रचुर, बहु, अल्पेतर. -**ness**, *s.* साधुता, प्रशस्तता, गुणवत्ता, श्रेष्ठता, विशिष्टता. 2 साधुशीलता, सदाचारता, धार्मिकत्वं. 3 सुशीलता, दया, कृपालुत्वं, सद्भावः, सौजन्यं, सुजनता; 'tendency to g.' सत्वगुणः.

Goods, *s.* द्रव्यं, द्रव्यराशिः, विभवः, सामग्री, वस्तुजातं, द्रव्याणि-वस्तूनि (pl.). 2 भांडकं, भांडसमुदायः, पण्यं, भांडानि (pl.); 'household g.' गृहोपस्करः, गृहोपकरणानि.

Goose, *s.* हंसः (सी *f.*), चक्रांगः (गी *f.*), वरटः-टा; कलहंसः (सी *f.*); *See* **Gander**; 'ruddy g.' चक्रवाकः (की *f.*), चक्रः रथांगः, कोकः, द्वंद्वचरः. 2 **Fool**, q. v.

Gorbellied, *a.* महोदर, बृहत्कुक्षि, तुंदिल, स्थूलोदर; *See* **Corpulent**.

Gore, *s.* रक्तं, शोणितं, रुधिरं, असृज् *n.*, लोहितं. 2 रक्तगुल्मः, रक्तपिंडः. 3 संचितरक्तखंडः. -*v. t.* व्यध् 4 P, निर्भिद् 7 P, छिद् 7 P, वि-दृ 10, क्षण् 5 P, उल्लिख् 6 P. -**ed**, *a.* छिन्नत्वच्, क्षतचर्मन्. -**y**, *a.* रक्ताक्त, असृग्दिग्ध. 2 रुधिरप्रिय, मारात्मक.

Gorge, *s.* कंठः, गलः. 2 रंध्रं, दुर्गमार्गः, संकट-संबाध-पथः, संचारः, संकटं, गिरिकंदरः. -*v. t.* उद्-ग्रस् 1 A, गॄ 6 P. 2 (One's self) कुक्षिं पूर् 10, अत्यंतं तृप् c., अन्नादिना परिपॄ 3 P.

Gorgeous, *a.* शोभन, उज्ज्वल, अतिशोभन, विभ्राजमान, तेजस्विन्, सुप्रभ, एकांतरमणीय-चारु, महाप्रभ-दीप्ति, विचित्र. -**ly**, *adv.* अतितेजसा, उज्ज्वलं. -**ness**, *s.* औज्ज्वल्यं, अति-प्रभा-तेजस् *n.*, सुप्रभा.

Gorget, *s.* ग्रीवा-गल-त्राणं.

Gormand, *See* **Glutton**. -**ize**, *v. i.* अत्याहारं or अतिभोजनं कृ 8 U. -**izer**, *s.* *See* **Glutton**.

Gosling, *s.* हंसशिशुः-शावकः.

Gospel, *s.* सुवार्ता, शुभवार्ता.

Gossamer, *s.* ऊर्णनाभजालतंतु *m.*

Gossip, *s.* वावदूकः, प्रलापिन् *m.*, जल्पकः. 2 पानमित्रं, सहपायिन् *m.* 3 वार्ता, जनप्रवादः, जल्पः, जल्पितं, प्रलापः, प्रजल्पः, वृथाकथा-संलापः. -*v. i.* प्रजल्प् 1 P, प्रलप् 1 P.

Gouge, *v. t.* (नयनं) उत्पट् 10, उद्धृ 1 P.

Gourd, *s.* अ(आ)लाबु-बू *f.*, तुंबि-बी *f.*, लाबु-बू *f.*, तुंबा. 2 (Vessel of g.) कमंडलुः; 'bitter g.' इक्ष्वाकु *f.*, कटुतुंबी.

Gourmand, *See* **Gormand**.

Gourmet. *s.* आस्वादपरायणः.

Gout, *s.* वातरक्तं, वातशोणितं. -**y**, *a.* वातग्रस्त, वातरोगोपहत, वातरोगिन्, वातकिन्.

Govern, *v. t.* प्र-शास् 2 P, परि-पा c. (पालयति), ईश् 2 A (with gen.); गुप् 1 P, तंत्र् 10 A, नियम् 1 P; *See* **Rule**. 2 वि-धा 3 U, वि-नी 1 P, निग्रह् 9 P, सं-नि-यम्, आ-वृ 5 U, वशीकृ 8 U, दम् c. (दमयति), सं-हृ 1 P, नि-यंत्र् 10; *See* **Control**. 3 (In grammar) अनु-इ 2 P, वि-धा; 'g.-ed by another' परायत्त, पराधीन, परतंत्र, विधेय. -**ment**, *s.* नियमनं, सं-नि-यमः, निग्रहः. 2 शासनं, परिपालनं; 'during the g. of Rama' रामे महीं शासति. 3 प्रभुत्वं,

ईशत्वं, ऐश्वर्यं, आधिपत्यं, स्वामित्वं. 4 राज्यं. 5 (Rulers) राजन् *m.*, प्रभुः, ईशः, राजमंत्रिगणः-सचिवाः; 'g. affairs' राज्यकार्याणि; 'form of g.' राज्यरीति-पद्धति *f.* **-or,** *s.* शासितृ *m.*, शासकः, ईशः, अधिपतिः, अधिष्ठातृ *m.*, अधिपः, अधिकृतः. 2 (Of a province) भोगपतिः. **-orship,** *s.* आधिपत्यं, प्रभुत्वं.

Gown, *s.* शाटः-टी, शाटकः, कटिवस्त्रं; 'girl's g.' अर्धोरुकं, चंडातकः-कं

Grab, *s.* ग्रहः,धरणं, संग्रहः. *-v. See.* **Snatch.**

Grabble, *v.* स्पृश्-परामृश् 6 P. 2 भूमौ देहं क्षिप् 6 P.

Grace, *s.* प्रसादः, अनुग्रहः, दया, कृपा, अनुकंपा, आनुकूल्यं. 2 सौंदर्यं, श्रीः, चारुता, शोभा, लावण्यं; *See* **Beauty. 3** गुणः, भूषणं. 4 क्षमा, पापमार्जनं-निष्कृति *f.* 5 (As a title) देवः-वी, अत्र-तत्र-भवान्-भवती. *-v. t.* अलंकृ 8 U, शुभ् c., भूष् 10, उद्-द्युत् c. (जाते पुतरप्युद्द्योतयोरसंग U. 4); संमन् c. सं-भू c.; 'g. the ceremony with your presence' संनिधानेन इमं विधिं संमानयतु-अलंकरोतु-भवान्. **-ful,** *a.* ललित, चारु, सुंदर (री *f.*), सुभग, लावण्यवत्, मुग्ध, सविलास; 'g. movement' मुग्धचेष्टा, विलासः, विभ्रमः, ललितं, हेला, लीला, हावः, बिब्बोकः, शृंगारचेष्टा-क्रिया; 'g. speech' वाग्विलासः; 'g. gait' खेलगति *f.*, विलासगतं. **-fully,** *adv.* सविलासं, ललितं, सुंदरं, चारुतया. **-fulness,** *s.* लावण्यं, श्रीः, शोभा, लालित्यं, मुग्धता; *See* **Beauty. -less,** *a* रूपहीन. 2 निर्लज्ज, दुराचार, दुर्वृत्त, अतिदुष्ट, दुष्टभाव. **-Gracious,** *a.* प्रसन्न, सदय, दयाशील, अनुकूल, अनुकंपिन्, दयालु, अनुकंपाशील, अनुग्राहिन्, कृपालु, सानुक्रोश, हितबुद्धि, सानुकंप; 'to be g.' प्रसद् 1 P, अनु-कंप् 1 A. **-ly,** *adv.* सानुग्रहं, सदयं, सानुकंपं, दयया, कृपया, प्रसन्नतया, सप्रसादं. **-ness,** *s.* प्रसादः, अनुकंपा, दयालुत्वं, अनुग्रहः, दया, कृपा &c.

Gradation, *s.* क्रमः, आनुपूर्व्यं, पर्यायः, अनुक्रमः, परंपरा, समन्वयः, परिपाटि-टी *f.*, 'in regular g.' यथाक्रमं, क्रमशः, अनुपूर्वशः, पर्यायेण.

Grade, *s.* श्रेणि-णी *f.*, प्रकारः, वर्गः, परिपाटि-टी *f.*, क्रमः, परंपरा, आनुपूर्व्यं. 2 पदं, अवस्था, आस्पदं, पदवि-वी *f.*, कोटि *f.*, काष्ठा (highest g.). **-Gradual,** *a.* क्रमिक, आनुक्रमिक, अनुपूर्व, उत्तरोत्तर; better ex. by 'g. ly.' **-ly.** *adv.* क्रमशः, शनैः शनैः, क्रमतः, क्रमेण, यथाक्रमं, अनुक्रमं, अल्पाल्पशः, उत्तरोत्तरं, प्रति-अनु-पदं, पदे पदे, अनुपूर्वशः, आनुपूर्व्येण. **-Graduate,** *v. t.* क्रमचिह्नैः अंक् 10. 2 उपपदं प्राप् 5 P. *-s.* उपपद-उपाधि-पद-युक्तः. **-ion,** *s.* क्रमचिह्नांकनं. 2 **Gradation,** q. v.

Graft, *v. t.* (fig.) निविश् c., नि-धा 3 U.

Grain, *s.* धान्यं, शस्यं, व्रीहिः, स्तंबकरिः, बीजरुहः, जीवसाधनं. 2 बीजं. 3 कणः-णिका, लवः, लेशः, अणुः. 4 काष्ठरेखा-शिरा, 'fried g.' लाजाः, भ्रष्टयवाः; पृथुकः, चिपिटकः; 'against the g.' प्रतिलोमं, विरुद्धं, विप्रतीपं, निरुत्साहं, कथमपि; 'with the g.' अनुलोमं; 'chaffless g.' धान्यास्थि *n.* **-y,** *a.* धान्य-शस्य-मय (यी *f.*).

Gram, *s.* चणकः.

Gramarie (y) (ye), *s.* माया, इंद्रजालं.

Gramineous, *a.* तृणमय (यी *f.*), शाद्वल.

Graminivorous, *a.* तृण-शष्प-भोजिन्, तृणभुज्.

Grammar, *s.* व्याकरणं, व्याकरणशास्त्रं-विद्या, शब्दशास्त्रं. **-ian,** *s.* वैयाकरणः, व्याकरणज्ञः, शब्दशास्त्रविद् *m.* **-Grammatical,** *a.* व्याकरणविषय, व्याकरणानुसारिन्, gen. (*s.*) in comp.

Granary, *s.* कुशूलः, धान्यकोष्ठः; धान्यागारं, कोष्ठोलः, पिटः.

Grand, *a.* महत्, बृहत्, गुरु. 2 उत्तम, प्रधान, मुख्य, अग्र, अग्र्य, विशिष्ट. 3 सुप्रभ, भव्य, प्रतापवत्, तेजस्विन्, उज्ज्वल; 'g.-child' पौत्रः-त्री; 'g.-daughter' पौत्री, पुत्रसुता, दौहित्री; 'great g.-daughter' प्रपौत्री; 'g.father' पितामहः, मातामहः (maternal); 'great g.-father' प्रपितामहः, प्रमातामहः; 'g.-mother,' पितामही, मातामही; वृद्धा, स्थविरा; 'g.-nephew' भ्रातृपौत्रः, स्वसृपौत्रः (त्री *f.*); 'g.-son' पौत्रः, पुत्रसुतः, नप्तृ *m.*, दौहित्रः, पुत्रिकासुतः; 'great g.-son' प्रपौत्रः, &c.; 'great great g.-son' परप्रपौत्रः. **-ly,** *adv.* वैभवेन, तेजसा; ऐश्वर्येण, महाप्रतापेन. उज्ज्वलं, सुप्रभं, उत्कृष्टं, परमं, श्रेष्ठतया **-ness,-Grandeur,** *s.* महत्त्वं, महिमन् *m.* 2 माहात्म्यं, औदार्यं, उत्कर्षः; श्रेष्ठता, प्राधान्यं. 3 वैभवं, तेजस् *n.*, विभूति *f.*, प्रतापः, शोभा, उज्ज्वलता, प्रभावः, ऐश्वर्यं, संपद् *f.* **-Grandee,** *s.* कुलीनः, कुलीनजनः, आभिजनः, महाजनः.

Grandiloquent, *a.* गर्वितवाच्, सदर्पवादिन्. **-Grandiloquence,** *s.* अतिशयोक्ति *f.*, दर्पवाक्यं, साहंकारं वचनं, दर्पाध्मातं वचनं.

Grange, *s.* क्षेत्रं क्षेत्रभूमि *f.*

Granivorous, *a.* शस्याद्, शस्यभक्षक.

Grant, *v. t.* दिश् 1 P, दा 3 U, 1 P, प्रतिपद् c.; *See* **Give. 2** अनुमन् 4 A, अनु-ज्ञा 9 U, अनु-मुद् 1 A. 3 ग्रह् 9 U, अंगीकृ 8 U, उरीकृ, स्वीकृ, प्रतिपद् 4 A, अभ्युपगम् 1 P, अभ्युप-इ 2 P, 'I g.,' 'g. ed' gen. ex. by कामं followed by तु, तथापि or पुनः; or by imp.; 'well it is g. ed' भवतु,

एवमस्तु, गृहीतमिदं.-s. प्रदानं, दानं, उत्सर्गः, दायः, विहापितं, उपायनं; *See* **Gift**; 'g. of property' निबंधः; 'royal g.' (gifts of land, &c.) शासनं, पट्टः, शासनपत्रं; 'a written g.' लेखपत्रं. **-ee,** *s.* प्रतिग्रहीतृ *m.*, दानभोगिन् *m.*, आदातृ *m.* **-or,** *s.* दातृ *m.*

Granule, *s.* कणिका, लवः; बीजकं, अणुः. **-Granular,** *a.* बीजाकार, बीजमय (यी *f.*), कणमय.**-Granulate,** *v. t.* घनीकृ 8 U, संहतीकृ; सूक्ष्मकणान् बंध् 9 P, **-ion,** *s.* पोथकी.

Grape, *s.* द्राक्षा, मृद्वीका, गोस्तनी, स्वाद्वी, मधुरसा; (fruit) द्राक्षाफलं, &c.; 'g.-stone' द्राक्षाबीजं, अष्ठिला, अष्ठि *f.* **-Grapery,** *s.* द्राक्षावाटिका.

Graphic, *a.* स्पष्ट, अर्थवत्, सुलिखित, सुचित्रित, सुनिर्दिष्ट.

Grapnel, *s.* क्षुद्रलंगरः. 2 आकर्षणी.

Grapple, *v. t.* धृ 1 P, 10, संग्रह् 9 P, आकृष् 1 P; नि-सं-बंध् 9 P, संश्लिष् c. **-v. i.** युध् 4 A, संघट्ट् 1 A, बाहूबाहवि or हस्ताहस्ति युध्; अभिसं-पत् 1 P. **-s.** संग्राहः-धरणं 2 बाहुयुद्धं. 3 आकर्षणी.

Grasp, *v. t.* ग्रह् 9 U, धृ 1 P, 10, (fig. also). आकल् 10, आकृष् 1 P, मुष्टिना ग्रह्; अवलंब् 1 A, परामृश्-स्पृश् 6 P. 2 ग्रस् 1 A, आक्रम् 1 U, 4 P; आ-घ्रा 1 P, आ-अवलिह् 2 U; 'g.-ed by death' कालग्रस्त; 'g.-ed by a tiger' व्याघ्राघ्रात, &c.; 'he quickly g. ed what I meant' मदाशयं झटिति गृहीतवान्. 3 (at) ग्रह् desid. (जिघृक्षति), हृ desid. (जिहीर्षति); आप् desid. (ईप्सति), लंघ् 1 A, 10, *See* **Aspire.** **-s.** ग्रहः-हणं, धरणं, परामर्शः मुष्टिग्राहः, संग्राहः, हस्तग्राहः, आक्रमः, ग्रसनं; gen. ex. by गोचरः, वशः, विषयः, मुखं; 'is within the g. of death' मृत्योर्मुखे वर्तते, कालालीढः, मृत्युगोचरं गतः, &c.; 'and this g. over every (kind of) learning' इदं च अशेषविद्याग्रहणसामर्थ्यं (Ka. 96); 'firmness of g.' दृढमुष्टिता, निबिडमुष्टिः.

Grass, *s.* तृणं, शस्यं, शादः; 'young g.' शष्पं, बालतृणं, घासः; 'meadow g.' य(ज)वसः; 'sacrificial g.' दर्भः, कुशः-शं. 'g.-green' शादहरित, शाद्वल; 'g.-hopper' शल(र)भः; 'g.-plot' शाद्वलं, तृणभूमि *f.* **-y,** *a.* तृणावृत, बहुतृण, तृणपूर्ण, सतृण, बहुघास, शाद्वल, घास-तृण-मय (यी *f.*). 2 हरित, शादहरित.

Grate, *s.* चुल्लि-ल्ली *f.*, अधिश्रयणी; *See* **Fireplace.** 2 लोहजालं. **-v. t.** घृष् 1 P, निष्पिष् 7 P, क्षुद् 9 P, संघट्ट c. 2 बाध् 1A, पीड् 10. व्यथ् c. (व्यथयति), संतप् c., मर्माणि छिद् 7 P or स्पृश्-तुद् 6 P. 3 घर्षेण चूर्ण् 10, पिष्, क्षुद् 7 P. 4 लोहजालेन युज् 10; 'g. the teeth' दंतैर्दंतान् निष्पीड् or घृष्. **-ing,** *a.* कर्कश, परुष, निष्ठुर, खर, कटु, मर्मस्पृश्-च्छिद्, अरुंतुद; 'g. to the ear' श्रवणकटु. **-s.** अन्योन्यघर्षणं, कर्कशध्वनिः. 2 लोहजालं, लोहशलाकासनाथः गवाक्षः. **-ingly,** *adv.* कर्कशं, निष्ठुरं, कटु.

Grateful, *a.* सुखकर (री *f.*), रम्य, रमणीय, आनंदावह, सुखावह, हृद्य, सुभग, मनोरम. 2 कृतज्ञ, कृतवेदिन्, उपकृतिज्ञ, कृतविद्, उपकारज्ञ. **-ly,** *adv.* कृतज्ञतया. 2 सुभगं, रम्यतया. **-ness,-Gratitude,** *s.* कृतज्ञता, उपकारस्मरणं, उपकृतज्ञता, कृतवेदित्वं.

Grater, *s.* घर्षणी, घर्षणयंत्रं.

Gratify, *v. t.* तुष् c., सं-परि°, आनंद् c., प्री 10, तृप् c., प्रमुद् c., हृष् c., रम् c., आह्लाद् c., *See* **Delight** also. 2 अनु-वृत् 1 A, अनुरुध् 4 A, लल् 10, प्र-सद् c., आराध् c., अनुरंज् c., सांत्व् 10. 3 शम् c. (शमयति), पृ c., or पूर् 10, साध् c., निर्वृत् c.; 'having all desires g. ed' पूर्णकाम, कृतार्थ, कृतिन्, सिद्धार्थ, निवृत्तकाम; 'g. ed at heart' प्रीत-हृष्ट-चित्त. **-ication,** *s.* सं-, परि-,तोषः, आनंदः, तृप्ति *f.*, तुष्टि *f.*, प्रीति *f.*, सुखं, हर्षः, आह्लादः, प्रमोदः. 2 आराधनं, अनुरोधः, अनुवर्तनं, प्रसादनं, तर्पणं, तोषणं. 3 शांति *f.*, शमनं, सिद्धि *f.*, साधनं, पूरणं, निर्वर्तनं; 'g. of desire' मनोरथसिद्धिः, इष्टसाधनं; 'g. of another's whim' छंदोनुवृत्ति *f.*, वर्तनं. **-ing,** *a.* संपरितोषक, तुष्टि-प्रीति-द, सुखावह, आनंदप्रद, सुख-प्रीति-कर (री *f.*).

Gratis, *adv.* विना मूल्येन, धर्मार्थं, निर्मूल्यं.

Gratuitous, *a.* अमूल्यवत्, निर्मूल्य, मूल्यं विना दत्त, कामतः दत्त. 2 अमूलक, निष्कारण, निर्निमित्त, अहेतुक. **-ly,** *adv.* निर्मूल्यं.

Gratuity, *s.* प्रदानं, उपायनं; *See* **Gift.**

Gratulate, *See* **Congratulate.**

Gravamen, *s.* पीडा, दुःखं.

Grave, *a.* गुरु, महत्, अलघु. 2 ग(गं)भीर, धीर, अचपल. 3 (Sound) मंद्र, घन, गंभीर, धीर, मंद्र, मंथर; 'g. matter' गुर्वर्थः. **-s.** प्रेत-शव-स्थानं; समाधिः, श्मशानं, अवटः; 'g. clothes' प्रेतवासस् *n.*, शववस्त्रं; 'g.-stone' चित्यं, चैत्यं, समाधिप्रस्तरः. **-v. t.** तक्ष् 1, 5 P, त्वक्ष् 1 P. **-ly,** *adv.* गंभीरतया, धीरं, सगौरवं, गांभीर्येण. 2 मंद्रं, धीरं, गंभीरं. **-ness,** *s.* गुरुता-त्वं, गौरवं, महत्त्वं. **-Gravity,** *s.* गुरुत्वं, भारः. 2 गौरवं, गुरुत्वंता, महिमन् *m.*, गांभीर्यं; अलाघवं, धीरता, मंद्रता. 3 आकर्षणशीलता, आकर्षणशक्ति *f.* **-Gravitate,** *v. i.* आकृष् pass., अधः गम् or पत् 1 P. **-ion,** *s.* आकर्षणं, अधःपतनशीलता.

Gravel, *s.* शर्करा, वालुका, शिला-पाषाण-खंडः-चूर्णं. 2 (Disease) अश्मरि, मूत्रकृच्छ्रं, मूत्रशर्करा. **–***v. t.* शर्करावृत *a.* कृ 8 U. 2 मुह् c., सं-वि-भ्रम् c. (भ्रमयति). **–ly,** *a.* सशर्कर, शर्करित, शर्करावृत, शर्करावत्, शार्करीय.

Graveolent, *a.* दुर्गंध, पूतिगंधि.

Gravid, *See* **Pregnant.**

Gravy, *s.* मांससारः, मांसजूषं.

Gray, *a.* आपांडु, धूसर, पांशुवर्ण, आशुक्ल. 2 शुक्ल, धवल, श्वेत, पक्व, पलित (hair); ' g. beard ' जीर्णकूर्चं; ' g. head ' पलितं शिरः; ' g.-haired ' पलित, धवल-शुक्ल-केश; ' g.-headed ' पलितशिरस्. 3 जीर्ण, परिणत, पक्व, वृद्ध. **–***s.* धूसरः, धूसर-पांशु-वर्णः. **–ish,** *a.* आपांडु, पांडुर, आधूसर; 'g. with dust' धूलिधूसर. **–ness,** *s.* धूसरता, पलितता, केशधावल्यं, पक्वता, जीर्णता.

Graze, *v. t.* चर् c., तृणं भुज् c. or खाद् c. 2 निर्घृष् 1 P, लघु तड् 10, लघुप्रहारेण अति-इ 2 P. **–***v. i.* चर् 1 P, तृणं खाद् 1 P or भक्ष् 10 or भुज् 7 A; 'a place g. ed by cattle ' आशितंगवीनं **–er,** *s.* तृणभक्षकः. **–ing,** *s.* चरणं; ' g. ground ' गोचरः, गोप्रचारः. **–Grazier,** *s.* गोचारकः, पशुपालः, गोपालकः.

Grease, *s.* वसा, मेदस् *n.*, वपा, मांसस्नेहः-सारः. 2 स्नेहः, तैलं, घृतं. **–***v. t.* वसया-स्नेहेन लिप् 6 P or अंज् 7 P or दिह् 2 U. **–y,** *a.* मेदस्विन्, वसामय (यी *f.*), चिक्कण, प्र-,स्निग्ध, वसाक्त, स्नेहाभ्यक्त, सस्नेह, वसास्नेह-युक्त.

Great, *a.* महत्, गुरु, बृहत्, विशाल, विपुल, विस्तीर्ण, उरु, पृथु, स्थूल, महाप्रमाण. 2 (In number) बहु, भूरि, प्रचुर, बहुल, बहुसंख्याक. 3 उत्कृष्ट, उत्तम, परम, विशिष्ट, विश्रुत, श्रेष्ठ, लब्धप्रतिष्ठ, प्रसिद्ध, महायशस्क. 4 महेच्छ, महाशय, महात्मन्, उदार, उदारचित्त. 5 प्रधान, मुख्य, परम, अग्र्य, गुरु. 6 अत्यंत, अतिमात्र, गाढ, अधिक, भृश, परम, एकांत, नितांत, अतिरिक्त; oft. by महत्, सु, अति, in comp.; ' to a g. distance,' सुदूरं, अतिदूरं; ' to a g. degree ' भृशं, अतिमात्रं, अत्यंतं, निर्भरं, गाढं. **–ly,** *adv.* भृशं, अत्यंतं, सातिशयं, सु-नि-तरां, एकांततः, परं, बलवत्, गाढं, परमं, सु-अति-अतिशय in comp.; *See* **Exceedingly**; oft. ex. by कोटि *f.*, काष्ठा; ' he was g. delighted ' आनंदस्य परां कोटिं-काष्ठां अधिगतवान्. **–ness,** *s.* महत्त्वं, माहात्म्यं, महिमन् *m.*, गुरुत्वं; विपुलता, विशालता, &c. 2 विस्तारः, परिमाणं. 3 विश्रुति *f.*, उत्कर्षः, विशिष्टता, परमता, आधिक्यं, प्रतिष्ठा, गौरवं. 4 वैभवं, शोभा, ऐश्वर्यं; *See* **Grandeur**; ' g. of mind ' औदार्यं, माहात्म्यं; ' g. of rank ' कुलीनता, अभिजात्य, कुलोत्कर्षः.

Greaves, *s.* जंघा-ऊरु-त्राणं, मंजुक्षणं.

Greed, *s.* लोभः, गृध्नुता, अतिस्पृहा, लौल्यं, लुब्धता, अत्यभिलाषः, अतिलिप्सा, अत्याकांक्षा, लोलुपत्वं, अतृप्ति *f.*, अपरितोषः. 2 (Of food) अत्याहारः, घस्मरता, अद्मरता, उदरंभरित्वं. **–Greedy,** *a.* लुब्ध, लोलुप, लोलुभ, गृध्नु, लोभाविष्ट, अत्यभिलाषिन्, अत्याकांक्षिन्, सतृष्ण, अतितृष्णाकुल, अतिलोभिन्. 2 आहारलुब्ध, अत्याहारप्रिय, घस्मर, अद्मर, अतिभोजिन्, बहुभुज्, औदरिक, उदरंभरि, कुक्षिंभरि, बहुभक्षक; 'to be g.' गृध् 4 P, लुभ् 4 P. **–ly,** *adv.* अतिलोभेन, सलोभं, सतृष्णं, लोलुपतया, जिह्वालौल्यात्, अत्यभिलाषेण, अतिस्पृहया. **–ness,** *s.* लोभः; *See* (*s.*).

Green, *a.* हरित, हरित्, हरिद्वर्ण; प(पा)-लाश 2 नव, प्रत्यग्र, अभिनव. 3 अपरिपक्व, अपरिणत; ' g.-headed' अपरिणतप्रज्ञ, अपक्वधी. **–***s.* हरिद्वर्णः, हरितः, हरित् *m.*, पालाशवर्णः. 2 हरितस्थानं, शाड्वलं, शाड्वलस्थली, तृणावृता भूमिः; ' g.-leaved ' हरित्पर्ण; ' g.-room ' नेपथ्यशाला; ' g.-sward ' हरितभूमिः, तृणावृतं स्थानं, हरितकं, शाकादि. **–ish,** *a.* ईषद्धरित, हरिदाभ, ईषत्पलाश. **–ness,** *s.* हरितत्वं, पलाशत्वं. 2 अपरिणतत्वं, अपरिपाकः, अपक्वता.

Greet, *v. t.* अभिनंद् 1 P or c., सभाज् 10, वंद् 1 A, अभिवद् c. (A), अर्च् 1 P, 10, सं-भू c., सत्कृ 8 U, पूज् 10; नमस्कृ, प्रणम् 1 P; ' g. in return ' प्रतिनंद्, प्रत्यभि-वद् c. **–ing,** *s.* प्रणामः, प्रणति *f.*, अभिवंदनं, अभिनंदनं, नमस्कारः, अभिवादः-वादनं, कुशलवादः-प्रश्नः.

Gregarious, *a.* यूथचारिन्, संघचारिन्.

Grey, *See* **Gray.**

Grice, *s.* शूकरशावकः-शिशुः.

Gridelin, *s.* श्वेतारुणः.

Grieve, *v. t.* दु 5 P, पीड् 10, बाध् 1 A, क्लिश् 9 P, व्यथ् c. (व्यथयति), उप-सं-परि-तप् c., आयस् c., उद्विज् c., दुःखयति (D.), शुच् c., खिद् c , ' it g. s me to see you in this condition ' एतदवस्थं त्वां वीक्ष्य दुःखितोस्मि. **–***v. i.* शुच् 1 P, व्यथ् 1 A, दुर्मनायते (D.), उत्तम् 4 P, उत्कंठ् 1 A, पीड्-खिद्-क्लिश्-दु-तप्-pass., दुःखायते (D.), उद्विज् 6 A, उत्सुक-उत्क-*a.* भू. **–ance,** *s.* दुःखं, क्लेशः, कष्टं, बाधा, पीडा, पीडाहेतुः, दुःखमूलं-बीजं-कारणं. **–ed,** *a.* दुःखित, दून, पीडित, व्यथित, संतप्त, शोकार्त, दुःखाकुल, शोकातुर, खेदित, क्लिष्ट, उद्विग्न, आतुर, आर्त, कष्टापन्न, उत्सुक, उत्क. **–ingly,** *adv.* सशोकं, सोद्वेगं, सदुःखं. **–ous,** *a.* दुःखकर-व्यथाकर-कष्टकर (री *f.*), पीडावह, क्लेशप्रद, पीडाजनक, शोच्य, शोचनीय, दुस् pr. 2 घोर, उग्र, दारुण, महत्,

शुरु. -ously, *adv.* घोरं, दारुणं, सशोकं; 'g. hurt' बलवत् पीडित, घोरक्षत, &c. -Grief, *s.* शोकः, दुःखं, शुच् *f.*, क्लेशः, खेदः, सं-परि-तापः, व्यथा, मन्युः, पीडा, अ-आर्ति *f.*, उद्वेगः, आधिः, वेदना, मनस्तापः, चित्तव्यथा, औत्सुक्यं, उत्कंठा.

Grill, *See* **Fry**.

Grim, *a.* उग्र, दारुण, घोर, भयानक, रौद्र (द्री *f.*), विकृत, विकट. 2 (In appearance) उग्रदर्शन, घोराकृति, रौद्ररूप, कद्राकार, दुर्दर्शन, कु-अप-रूप. -ly, *adv.* उग्रं, घोरं, विकटं. -ness, *s.* घोरता, रौद्रता, &c.

Grimace, *s.* वदनविकारः-विकृति *f.*; मुख-वक्त्र-भंगः, मुखविरूपता, वक्रमुखं, विकृतास्यं.

Grime, *s.* मलः-लं; *See* **Dirt**. -*v. t.* मलिनयति (D.), दुष् c. (दूषयति).

Grin, *v. i.* सस्मितं दतान् दृश् c; कु-स्मि 1 A or हस् 1 P, विकृत-मुखविकारेण हस् or स्मि. -*s.* कुस्मितं, कुहासः, विकृतहासः-स्मितं, दंतदर्शनं. -ner, *s.* कु-विकृत-हासिन् *m.*, विकृतहासः.

Grind, *v. t.* पिष् 7 P, क्षुद् 7 P, मृद् 9 P, चूर्ण् 10, चूर्णीकृ 8 U; चूर्णपेषं पिनष्टि; 'g.s to powder'. 2 (As a gem) उल्लिख् 6 P, उल्लिह् 2 U; संस्कारोल्लिखितः-शाणोल्लीढः-मणिः 'a gem ground on a polishing or touch-stone'; घर्षणेन नि-शो 4 P or उत्तिज् c. 3 घृष् 1 P; 'g. ing the teeth in rage' रोषाद् दंतैर्दंतानभिनिष्पिष्य. 4 उप-द्रु 1 A, बाध् 1 A, पीड् 10, अर्द् 1 P or c.; 'ground by heavy taxes' करभारेण चूर्णित-पीडित, &c. -er, *s.* पेषकः. 2 (g. stone) पेषणं-णी, पेषणयंत्रं. 3 चर्वणदंतः, दंष्ट्रा. -ing, *s.* पेषणं, चूर्णीकरणं, संमर्दनं, घर्षणं, उल्लिखनं; 'g. stone' पेषणं-णी, पेषणशिला, शाणः, निकषशिला.

Grip, *s.* दृढग्रहः. -*v. t.* दृढं ग्रह् 9 U.

Gripe, *v. t.* ग्रह् 9 U, मुष्टिना ग्रह् or धृ 1 P; *See* **Grasp**. 2 पीड् 10, सं-नि°. 3 मुष्टिं बंध् 9 P. -*s.* मुष्टिग्राहः, हस्तग्रहः, संग्राहः, दृढग्रहः, मुष्टिबंधः, मुष्टि *m.*, *f.* 2 निपीडनं. 3 (g. s) अंत्रशूलं, वेदना, उदरशूलं-व्यथा. -er, *s.* ग्राहकः. 2 पीडकः, बाधकः.

Grisly, *a.* उग्रदर्शन, करालवदन, विकटाकार, घोराकृति, भीमविग्रह, उग्र, घोर, दारुण, भयानक, क्रूर, कराल, भयावह.

Grist, *s.* गोधूमचूर्णं, पिष्टधान्यं.

Gristle, *s.* तरुणास्थि *n.*, कोमलास्थि.

Grit, *s.* **Gravel**, q. v. -**Gritty**, *a.* सशर्कर, शर्करिल, शर्करामय (यी *f.*).

Grizzle, *s.* धूसर-पांडु-वर्णः. -**Grizzly**, *a.* ईषद्धूसर, आपांडुवर्ण.

Groan, *v. i.* दुःखवशात् क्वण्-स्वन् 1 P or नद् 1 P or रु 2 P or आक्रुश् 1 P, सशब्दं निश्वस् 2 P, आर्तरवं-दीर्घनादं-कृ 8 U. -*s.* दीर्घनिश्वासः, आर्तरवः-नादः, सनिश्वासं क्वणितं, सीत्कारः, ससीत्कारं परिदेवनं.

Grocer, *s.* वणिज् *m.*, नैगमः; *See* **Merchant**. -y, *s.* वाणिज्यं, वणिक्कर्मन् *n.*

Grog, *See* **Liquor**.

Groin, *s.* ऊरुसंधिः.

Groom, *s.* परिचारकः, भृत्यः, किंकरः; (strictly) अश्वपालः-रक्षकः-सेवकः.

Groove, *s.* रेखा, प्रणाली. 2 सुषिरं, दीर्घसुषिरं.

Grope, *v. i.* अंधकारे परा-मृश् 6 P, तमसि निरूप् 10 or अन्विष् 4 P or परीक्ष् 1 A.

Gross, *a.* स्थूलकाय, बृहत्, पीन, पीवर, मेदस्विन्. 2 घन, स्थूल, असूक्ष्म; 'g. measurement' स्थूलमानं. 3 गाढ, निबिड, निरंतर, अविरल, सांद्र. 4 अश्लील, ग्राम्य, नीच, अवाच्य, अशिष्ट, असभ्य, गर्ह्य, निंद्य, अशुद्ध, कुत्सित, नि-अप-कृष्ट, अपवित्र, मलीमस, अमेध्य, अयशस्कर (री *f.*). 5 जड, मूढ, मंद. 6 अविनीत, अमर्याद. 7 अत्यंत, अतिमात्र, महत्, सु-अति pr.; 'g. fault' महापराधः; 'g. body' स्थूल-जड-देहः; 'g. darkness' संतमसं, अंधं तमः. -*s.* स्थूलांशः, प्रधानभागः, प्रधानांशः, साकल्यं, सामग्र्यं, समासः; 'in the g.' स्थूलमानेन, साकल्येन. -ly, *adv.* स्थूलं, घनं, असभ्यं, गर्ह्यतया, नीचं; अत्यंतं, अतिमात्रं, अति-सु pr.; 'g. corrupted' अतिदुष्ट. -ness, *s.* स्थूलता, पीनता: निबिडता, अशिष्टता, ग्राम्यत्वं, अविनयः, अमर्यादा, अत्यंतता, अतिरेकः, गाढता, आधिक्यं.

Grot, Grotto, *s.* कुहरं, गह्वरं, गुहा, कंदरः, शैलविवरं; 'natural g.' देवखातं, देवखातबिलं; 'artificial g.' क्रीडाकुटीरः, कृत्रिमकंदरः.

Grotesque, *a.* वि-अप-रूप, विलक्षण, हास्यरूप, कदाकार, असंगताकार; हास्य, असंगत, असंबद्ध, विषम. -ly, *adv.* असंगतं, विलक्षणतया, हास्यरूपेण.

Ground, *s.* भूमि *f.*, भूः, क्षिति *f.*, मही, धरणिः, पृथ्वी; *See* **Earth**. 2 भूतलं-पृष्ठं-पीठं. 3 स्थलं, स्थली. 4 उपष्टंभः, वास्तु *m.* *n.*, गृहभूमिः-प्रतिष्ठा. 5 आधारः, मूलं, कारणं, निमित्तं, हेतुः, निदानं, प्रयोजनं. 6 मृत्तिका, मृद् *f.*, क्षेत्रं; 'gain g.' उप-चि pass., प्र-वृध् 1 A, एध् 1 A, वृद्धिं गम् 1 P; 'lose g.' क्षि-अपचि- pass., ह्रासं गम्; शनैः परा-निवृत् 1 A. -*v. t.* मूलं न्यस् 4 P or प्रतिष्ठा c. (प्रतिष्ठापयति); oft. by मूल in comp.; 'devotion g. ed on faith' श्रद्धामूला भक्तिः. 2 आरंभ-उपक्रमं शिक्ष् c. or अधि-इ c. (अध्यापयति); 'well g. ed in grammar' स्वधीतव्याकरणः; 'g.-floor' गृहतलं, कुट्टिमं, अधःकोष्ठः; 'g.-work' मूलकर्मन् *n.*, प्रारंभः, उपक्रमः, मूलं. -less,

a निर्मूल, निष्कारण, अहेतुक, अनिमित्त, निराधार, अमूलक; मिथ्या in comp. **-lessly,** *adv.* निष्कारणं, मिथ्या. **-lessness,** *s.* अकारणं, निर्मूलत्वं.

Grounds, (pl.) *See* **Dregs.**

Ground-sil, *s.* देहली, गृहावग्रहणी.

Group, *s.* संघः, निवहः, समुदायः; गणः; *See* **Multitude;** 'in g. s.' गणशः, संघशः. **-**v. t. एकीकृ 8 U, वर्गी-गणी-कृ, सं-चि 5 U; **Collect,** q. v.

Grove, *s.* उपवनं, वनराजि-जी *f.*, वृक्षवाटिका वनांतः; *See* **Forest** also.

Grovel, *v. i.* नीचतया भूमौ पत् 1 P or सृप् 1 P, अधमवत् आचर् 1 P, धूलिं स्पृश् 6 P. **-ing,** *a.* नीच, अपकृष्ट, अधम, तुच्छ, अतिक्षुद्र.

Grow, *v. i.* स्फुट् 6 P, विकस् 1 P, फुल्ल् 1 P. उद्भिद् pass. (generally of plants). **2** रुह् 1 P, ऋध् 4, 5 P, एध् 1 A; पुष् 4 P, वृध् 1 A, उपचि pass., स्फाय् 1 A, प्यै 1 A, वृद्धिं या-इ 2 P. **3** सं-,जन्, 4 A, भू 1 P. 'the beard having begun to g.' उद्भिद्यमानश्मश्रुराजितया (Ka. 29). **4** जन्, उत्पद् 4 A, उद्-इ 2 P, भू, उत्-सं-प्र°. **5** विस्तृ pass., व्याप् 5 P; 'g. up संवृध्, एध्, प्रौढिभू; 'bad boys g. to be bad men' कुबालाः कुनराएव निष्पद्यंते-भवंति; 'he was grown up', 'he grew up to man's estate (majority)' यौवनपदवीमारूढः, समारूढयौवनारंभः, प्रौढः, प्राप्तयौवनः, यौवनदशामापेदे, अतीत-गत-शैशवः; 'g. old' जॄ 4 P. **-**v. t. वृध् c., रुह् c. **-ing,** *a.* वर्धमान, उपचीयमान, वर्धिष्णु **2** रोहिन्, रुह, रुहु, भव, उद्भव, प्रभव, ज, जात, उत्थ, समुत्थ, भू, in comp.; 'g.-ing in size' प्र-उप-चीयमान-अवयव. **-Growth,** *s.* वृद्धि, आगमः, वर्धनं, उपचयः, ऋद्धि *f.*, स्फीति *f.*, अभ्युदयः, विस्तारः. **2** उत्पत्ति *f.*, सं-प्र-भवः, जननं, जन्मन् *n.* **3** प्रौढि *f.*, प्रवृद्धता.

Growl, *v. i.* भष् 1 P, गर्ज् 1 P, रे 1 P, घुर्घुररवं कृ 8 U. **-**s. भषणं, गर्जितं, घुर्घुररवः.

Grub, *See* **Dig.** **-**s. कीटः, कृमिः, कोशस्थः. **2** वामनः, खर्वः, ह्रस्वः.

Grudge, *v.* ईर्ष्य् 1 P, द्रुह् 4 P, असूयति (D.), (with dat.); न सह् 1 A, न मृष् 4 P, 10; *See* **Envy. 2** अकामतः-अनुत्साहं-अनिच्छया-कृ 8 U or दा 3 U or ग्रह् 9 U. **3** परि-देव् 1 A, परिदिव् 10 A, विलप् 1 P; *See* **Complain.** **-**s. असूया, मत्सरः, मात्सर्यं, ईर्ष्या. **2** वैरं, वैरभावः, विद्वेषः, चिर-दीर्घ-द्वेषः-वैरं. **-ingly,** *adv.* असूयया, साभ्यसूयं-सेर्ष्यं. **2** अकामतः, अनिच्छया, अनुत्साहं, कृच्छ्रेण, दुःखेन.

Gruel, *s.* यवागूः, उष्णिका, श्राणा, विलेपी, तरला; 'sour g.' आरनालकं, सौवीरं, कुल्माषाभिषुतं, अवंतीसोमं, धान्याम्लं, कुंजलं, कांजिकं.

Gruesome, *a.* भीषण **2** खेदकर.

Gruff, *a.* कर्कश, परुष, निष्ठुर, रूक्ष, कठोर, कटु, कर्कशस्वभाव. **2** (Voice) गंभीर, मंद्र.

Grumble, *v. i.* खिद् pass., असंतोषाद् विलप् 1 P or परिदेव् 1 A or परिदिव् 10 A, विषण्ण-*a.* भू 1 P, न तुष् 4 P, विषद् 1 P. **2** गर्ज् 1 P, स्तन् 1 P. **-ing,** *s.* विलापः, विलपनं, परिदेवनं-देवितं, असंतोषोद्गारः, विषादः. **2** गर्जनं, स्तनितं, गंभीरनादः-ध्वनिः-शब्दः.

Grume, *See* **Clot.**

Grumpy, *a.* दुःशील, उदासीन, उद्विग्न, विषण्ण, अंतःकुपित.

Grunt, *v. i.* गर्ज् 1 P. **-**s. **-ing,** *s.* गर्जितं, शूकरनादः-गर्जितं. **-ling,** *s.* बालशूकरः, शूकरशावकः.

Guarantee, *s.* प्रत्ययः, विश्वासः, प्रातिभाव्यं. **2** प्रतिभूः, लग्नकः, बंधकः. **-**v. t. Ex. by (s.); प्रातिभाव्यं दा 3 U, प्रतिभूः स्था 1 P; 'I g. you the security of your property' त्वद्वित्तरक्षणेहं प्रतिभूस्तिष्ठामि.

Guard, *v. t.* सं-,परि-,रक्ष् 1 P; पा 2 P; पा c. (पालयति), त्रै 1 A, अव् 1 P, गुप् 1 P; *See* **Protect. 2** वृ c., वार् 10, नि°; 'g. against' अव-धा 3 U; सावधान-अवहित-*a.* भू; *See* **Beware.** **-**s. रक्षा, रक्षणं, गुप्ति *f.*, गोपनं पालनं, त्राणं. **2** रक्षकः, रक्षिन् *m.*, रक्षिवर्गः, रक्षाधिकृतः, सैनिकः, परिचरः; वारणं, त्राणं, त्रं, in comp.; 'finger-g.' अंगुलित्रं, तनुत्राणं, &c., 'arm-g. in shooting' गोधा, तलं, ज्याघातवारणं; 'on one's g.' सावधान-अप्रमत्त-अवहित-*a.*; 'off one's g.' प्रमत्त *a.*; 'g.-room' रक्षकनिवासः, उद्घाटः. **-ed,** *a.* रक्षित, त्राण-त, &c. **2** (g.-ful) अवहित, सावधान, स्ववहित, समीक्ष्यकारिन्, समीक्ष्यकृत्. **-edly,** *adv.* सावधानं, विमृश्य, अवधानेन, स्ववहितं. **-er,** *s.* पालकः, रक्षकः, गोप्तृ *m.*, त्रातृ *m.*, पालः-लकः in comp. **-ian,** *s.* रक्षकः, रक्षितृ *m.*, गोप्तृ *m*, नाथः; 'orphan's g.' पितृस्थानीयः; 'g. deity' लोकपालः, दिक्पालः. **-ianship,** *s.* पालकपदं, रक्षा, रक्षण.

Guerdon, *See* **Reward.**

Guess, *v. t.* ऊह् 1 A; अनु-मा 3 A, 2 P; आशंक् 1 A, तर्क् 10. **-**s. वि-,तर्कः, ऊहा, अभ्यूहः-हनं; अनुमानं, अनुमिति *f.*, शंका; 'your g. is plain' प्रसन्नस्ते तर्कः.

Guest, *s.* अतिथिः, अभ्यागतः, प्राघूर्णकः, प्राघुणकः, आगंतुः, आवेशिकः, गृहागतः, आगंतुकः; 'friendly to g.s' आतिथेय (यी *f.*).

Guide, *v. t.* नी 1 P, पंथानं-मार्गं (way, q. v.) दृश् c. or आ-उप-दिश् 6 P. 2 प्र-अनु-शास् 2 P, निर्-उप-दिश्, विनि-यम् 1 P, प्र-णी 1 P, वि-धा 3 U; अधिष्ठा 1 P. -*s.* अध्वदर्शिन् *m.*, पुरोगः, सुखरः, मार्गोपदेशकः, नेतृ *m.*, नायकः, मार्गदर्शकः, उपदेशकः, निर्देशकः. 2 शास्तृ *m*, अध्यक्षः, अधिष्ठातृ *m.* **-ance,** *s.* नयः, नीति *f.*, मार्गदर्शनं, अध्वोपदेशः. 2 अनुसरणं, अनुवर्तनं.

Guild, *s.* श्रेणि-णी *f.*, निगमः, वणिक्समाजः-संसर्गः. 2 संघातः, समाजः, गणः.

Guile, *s.* माया, कपटः-टं, छलं, व्याजः, कैतवं, शाठ्यं, छद्मन् *n.*; *See* **Fraud. -ful,** *a.* मायिन्, वंचनशील, शठ, धूर्त, कापटिक (की *f.*), सव्याज, वंचक, मायान्वित, कितव. **-fully,** *adv.* सव्याजं, सकपटं, छद्मना, मायया. **-less,** *a.* निष्कपट, अकपट, अव्याज, अनुपधि,सरल, निर्व्यलीक, विमलात्मन्; *See* **Frank. -lessly,** *adv.* अमायया; निष्कपटं, निर्व्याजं, &c.

Guillotine, *s.* शिरश्छेदनयंत्रं.

Guilt, *s.* अपराधः, दोषः, पापं, पातकं, अघं, एनस् *n.*, पापकर्मन् *n.*, दुष्कृति *f.*, आगस् *n.*, दुरितं. 2 सदोषता, पापत्वं, अपराधिता. **-less,** *a.* निरपराध, अनपराधिन्, अनागस्, अपाप, निष्पाप; अकृतदोष, निर्दोष, अनघ, शुद्ध, पाप-दोष-हीन. **-lessly,** *adv.* निरपराधं, पापं-दोषं-विना. **-y,** *a.* पापिन्, अपराधिन्, सापराध, अपराद्ध, सपाप, पापकर्मन्, सदोष, कृतागस्, कृतापराध, दोष-पाप-वत्, पातकिन्, दुष्कृतिन्, पापात्मन्, पाप.

Guinea-worm, *s.* स्नायुकः.

Guise, *s.* वेशः-षः, वस्त्रं, परिधानं, रूपं, आकारः, छद्मन् *n.*; *See* **Disguise.**

Guitar, *s.* वीणा, वल्लकी, विपंची; सारंगी, पिनाकी; 'seven-stringed g.' परिवादिनी.

Gulf, *s.* अखातं, समुद्रवंकः, पुटभेदः. 2 अगाधं-अतल-स्पर्श-खातं, रंध्रं. 3 **Whirlpool,** q. v.

Gull, *v. t.* वंच् 10, प्रतॄ c.; *See* **Cheat.** -*s.* सुप्रतार्यः, सुखं वंचनीयः. 2 जलकुक्कुटः, विश्वका; 'g.-catcher' वंचकः, प्रतारकः. **-ery,** *s.* प्रतारणा, वंचनं-ना, छलं, कपटं.

Gullet, *s.* गलः, गलस्रोतस् *n.*, निगरणः.

Gully, *s.* प्रणालः-ली, कुल्या, जलमार्गः, परि(री)वाहः.

Gulosity, *s.* अतिभोजनं, घस्मरता, अत्याहारः.

Gulp, *v. t.* नि-गॄ 6 P, ग्रस् 1 A. 2 उद्-गॄ, उत्क्षिप् 6 P. -*s.* निगरणं, ग्रसनं. 2 उद्गिरणं, उद्गमः-मनं.

Gum, *s.* निर्यासः, रसः. 2 (Of teeth) दंतमांसं, दंतमूलं. 3 श्यान-सांद्र-द्रव्यं; 'g.-boil' दंतव्रणः-विस्फोटः. **-my,** *a.* श्यान, सांद्र, निर्यासमय (यी *f.*).

Gumption, *s.* चातुर्यं, बुद्धि *f.*, ज्ञानं.

Gun, *s.* लोहसुषि *f.*, गुलि-गुलिका-प्रक्षेपिणी लोहनाडिः-डी *f.*, अग्न्यस्त्रं; 'g.-powder आग्नेयचूर्णं.

Gunny, *s.* शाणं.

Gurge, *See* **Whirlpool.**

Gurgle, *v. i.* घर्घररवं कृ 8 U, गद्गदं गद् 1 P, (कुहरेषु गद्गदनदद्गोदावरीवारयः U. 2).

Gush, *v. i.* निष्पत् 1 P; बहुशः स्रु 1 P or नि-स्यंद् 1 A or क्षर् 1 P; वेगात् निः-सृ 1 P or प्रवृत् 1 A; तस्यास्तु महर्षिभाद्वेष आबद्धधारमश्रु प्रावर्तत (D. K. II. 3) 'tears g. ed forth from her eyes in torrents &c.', उद्बाष्पे नयने जाते. -*s.* जलप्रपातः, उत्पीडः, वेगेन निःसरणं, प्रवृत्ति *f.*

Gust, *s.* चंडवातः, वात्या, प्रकंपनः, जवानिलः, वायुवेगः, तीव्र-प्रबल-वातः-वायुः. 2 रुचि *f.*, आस्वादः, रसः. **-ful,** *a.* सरस, रुचिर. **-less,** *a.* विरस, अस्वादु. **-y,** *a.* पवनक्षिप्त, वातुल, वातमय (यी *f.*).

Gut, *s.* अंत्रं, पुरीतत् *n.*; शिरा, अंतर्नाडी. 2 उदरं, जठरः-रं. -*v. t.* अंत्राणि बहिष्कृ 8 U or निष्कुष् 1 P. 2 सर्वस्वं अपहृ 1 P.

Gutter, *s.* जलमार्गः, परि(री)वाहः, प्रणालः-ली.

Guttler, *See* **Glutton.**

Guttural, *a.* कंठ्य, कंठस्थ-स्थानीय.

Guzzle, *v. t* अतिमात्रं पा 1 P or ग्रस् 1 A or नि-गॄ 6 P.

Gymnasium, *s.* व्यायामभूमि *f.* -शाला. **-Gymnastic,** *a.* व्यायामशील-पर-सेविन्. 2 व्यायामसंबंधिन्; 'g. s' व्यायामः, व्यायामविद्या, मल्लक्रीडा.

Gynæ(e)cology, *s.* स्त्रीरोग-विज्ञानं-शास्त्रं

Gyrate, *See* **Revolve.**

Gyre, *s.* मंडलं, आवृत्ति *f.*, चक्रगति *f.*

Gyves, *s.* निगडः-डं, शृंखला-लं, पाशः, बंधनं.

H.

Ha, *interj.* हा, अहो, अयि, बत, हंत.
Haberdasher, *s.* क्षुद्रपण्यविक्रयिन् *m.*
Habergeon, *s.* वक्षस्त्राणं, उरश्छदः.
Habiliment. *See* **Dress.**
Habit, *s.* **Dress,** q. v. **2** शीलं, भावः, प्रकृति *f.*, स्थिति *f.*, वृत्ति *f.*, अवस्था, दशा, स्वभावः. **3** अभ्यासः, नित्यप्रवृत्ति *f.* आचारः, नित्यक्रिया, व्यवहारः, रीति *f*, प्रचारः, क्रमः, आवृत्ति *f.*, अनुशीलनं; 'in the h. of' शील or वृत्ति in comp.: 'in the h. of stealing' चौर्यवृत्ति; मृगयाशील, &c.: 'bad h.' व्यसनं, दुर्गुणः; 'having bad h.s.' दुर्वृत्त, दुराचार, पापवृत्ति, भ्रष्टचरित्र. **–***v. t.* **Dress,** q. v. **–able,** *a.*, वासक्षम, वसतियोग्य. **–ation,** *s.* वासः, धामन् *n.*, वसति *f.*, आलयः, गृहं, गेहं, आगारं; *See* **House. –ual,** *a* अभ्यासज, नित्य, सतत, अनुशीलित, आभ्यासिक-व्यावहारिक-स्वाभाविक (की *f.*); 'a h. drunkard' नित्यपानासक्तः; 'a h worker' क्रियावान्, कर्मसु उद्यतः कार्मः, कर्मशीलः. **–ually,** *adv.* नित्यं, सततं, यथाभ्यासं, यथारीति, यथाव्यवहारं. **–uate,** *v. t.* अभ्यस् 4 U. अनुशील् 10, शिक्ष् c., परिचि c., अभ्यस्त-परिचित -*a.* कृ. 8 U; 'h. ed to distress' ज्ञातदुःख, परिचितक्लेश; दुःखशील, दुःखाभिज्ञ.
Hack, *v. t.* खंडशः कृत् 6 P or छिद् 7 P, बहुलवशः व्रश्च् 6 P or विद् 10, व्यवच्छिद्. **–***s.* प्रहारः, छेदः, आघातः. **2** पण्याश्वः, कदश्वः, जीर्णः अश्वः, सर्वप्रयोज्यः-सर्वसाधारणः-अश्वः. **3** हीनवृत्तिः, नीचकर्मकारिन् *m.* ब्रातीनः, सर्वप्रयोज्यः, पण्यः.
Hackle, *s.* उमामार्जनी-शोधनी.
Hackney, *s. See* **Hack** (*s.*). **2** पण्यस्त्री, सर्वोपभोज्या. **–***v. t.* हीनकर्मणि नियुज् 7 A. 10; 'h.-coach' पण्यवाहनं, पण्य-साधारणरथः. **–ed,** *a.* जीर्ण, साधारण, बहुप्रयुक्त, सर्वसाधारण.
Hades, *s.* पातालोकः, पातालं, अधोलोकः-भुवनं.
Hæ(e)morrhage, *s.* रक्तस्रावः.
Haft, *See* **Handle.**
Hag, *s.* जरती, स्थविरा, कुरूपिणी. **–Haggard,** *a.* परिकृश, क्षाम, क्षीण, क्षाम-शुष्क-वदन, रूक्ष, उग्रदर्शन. **2** जरठ, स्थविर.
Haggle, *v. i.* क्रयविक्रयकाले विलंब् 1 A or विवद् 1 A.
Hagiology, सिद्धचरित्रलेखः.
Hail, *interj.* नमः, स्वस्ति, (with dat.); oft. ex. by जि 1 P; जयतु जयतु देवः 'h. to Your Majesty': कुशलं भूयात्, अभिवादये. **–***s.* शिलावृष्टि *f.*, करकानिपातः; 'h.-stone' करका वर्षोपलः, वर्षशिला, पयोघनः, घन-मेघ-कफः; 'h.-storm' करकासारः शिलावर्षः. **–***v. i.* उपलान् वृष् 1 P or निपत् c., करकासारं पत् c. **–***v. t.* वंद् 1 A, अभिवद् 10 A, संबुध् c., आमंत्र् 10 A आ-अभि-भाष् 1 A, आ-ह्वे 1 P. **2** (fig., प्रीत्या-मुदा-अंगीकृ 8 U; अभिनंद् 1 P.
Hair, *s.* केशः, कचः, वालः, चिकुरः, कुंतलः 'h. on the head' शिरोरुहः, मूर्धजः, शिरसिजः. **2** (Of the body gen.) रो(लो)मन् *n.*, तनूरुहः-हं, तनुजः; 'quantity of h.' कैश्यं, कैशिक. **3** केश(स)रः; 'whole collection of h.' केशकलापः-पक्षः-हस्तः-पाशः; 'h. hanging on the forehead' भ्रमरकाः; 'lock of h.' काकपक्षः, शिखंडकः; 'matted h.' जटा, सटा; 'a braid of h.' . री, केशवेशः; 'curled h.' अलकः, चूर्णकुंतलः; 'braided h' वेणि-णी *f*, धम्मिल्लः; 'crest-h.' शिखा, चूडा, केशपाशी; 'clean h.' शीर्षण्यः, शिरस्यः, 'h.-broom or brush' केशमार्जनी-शोधनी; 'h.-dressing' केशरचना-संस्कारः; 'even a h's breadth, रेखामात्रमपि; 'a h-breadth escape' कथमपि लब्धा मुक्तिः. **–less,** *a.* अकेश, केशहीन, विकेश. **–y** *a.* लोमश, लोमावृत प्रचुर-बहु-लोमन्, लोममय (यी *f.*), लोमवत्, लोमपूर्ण, केशव, कोशिन्, केशिक.
Halberdier, *s.* प्रासिकः, शाक्तीकः.
Halcyon, *s.* मत्स्यरंगः. **–***a.* शांत, निरुद्वेग, निराकुल, प्रसन्न, अक्षुब्ध, निर्वात.
Hale, *a.* सुस्थ, नीरोग, कल्य, निरामय, नीरुजज, आधिव्याधिरहित. **–***v. t.* आकृष् 1 P; *See* **Pull.**
Half, *a.* अर्ध, सामि in comp.; 'h. done' सामिकृतं. **–***s.* अर्धः-र्धं, अर्धभागः, अर्धांशः; in comp. ex. by अर्ध; अर्धांगं, पूर्वार्धः, &c.; 'a year and a h.' सार्धवत्सरः; 'h. eaten' अर्धभुक्त; अर्धविवृत, अर्धच्छिन्न, &c.; 'h.-brother' वैमात्रेयः, सापत्नः, अन्योदर्यः, वैमात्रः; h.-blood' भिन्नोदर, भिन्नगर्भ, अन्योदर्य; 'h. dead' मृतकल्प-प्राय, मरणोन्मुख, आसन्नमृत्यु, मुमूर्षु, कंठगतप्राण; h.-heart'd' निरुत्साह, उत्साहहीन, आस्थारहित; 'h. moon' अर्धेंदुः, चंद्रार्धः; 'h.-sister' वैमात्रेयी, वैमात्री, अन्योदर्या; 'h. starved' क्षुधावसन्नप्राय, क्षुत्क्षामकल्प; 'h. way' अर्धमार्ग-पथं, मध्यमार्गः; 'h. year' अर्धवर्षं; 'h. yearly' षाण्मासिक-आर्धवार्षिक (की *f.*): 'h. a bread is better than no loaf' सर्वनाशे समुत्पन्ने अर्धं त्यजति पंडितः or अर्धेन ... कार्यं.
Hall, *s.* क[illegible] ...ः, प्राह्यकोष्ठः.
Halloo, *interj.* हंहो, अहो, अरे, अये, भोभोः. **–***v. t.* उच्चैः शब्दायते (D.), दूरात् उत्क्रुश्-आह्वे, 1 P or उद्-घुष् 10.

Hallow, *v. t.* पवित्रीकृ 8 U, पूज् 10, मह् 1 P, 10, अर्च् 1 P, 10. **2** संस्कृ, प्रोक्ष् 1 P, अभिषिच् 6 P.

Hallucination, *s.* मतिविभ्रमः; माया, मोहः, भ्रमः, व्यामोहः, वंचना, इंद्रजालं.

Halm, *s.* पलालः-लं, तृणं.

Halo, *s.* प्रभा-तेजो-मंडलं, परिवेषः-शः, परिधिः, द्युति or दीप्ति-मंडलं-चक्रं-माला; 'h. crown of silver light' रजतधवलप्रभामंडलं: 'with a h. of brilliant lustre' स्फुरत्प्रभामंडल *a.*

Halser, *s.* नौगुणः-रज्जु *f.*

Halt, *v. i.* निविश् 6 P, अव-स्था 1 A, प्रयाणभंगं कृ 8 U, अध्वमध्ये स्था. **2** विरम् 1 P, विश्रम् 4 P. **3** लंग् 1 P. **-a.** पंगु, गति-विकल, श्रोण. **-** निवेशः, अवस्थिति *f.*, अवस्थानं, प्रयाणभंगः, याननिवृत्ति-विरति *f.*; विश्रामः; 'h. ing place' निवेशस्थानं. **2** लंगनं.

Halter, *s.* पाशः, गुणः, रज्जु *f.* कंठपाशः. **-***v. t.* कंठपाशेन बंध् 9 P or संयम् 1 P.

Ham, *s.* जंघा, प्रसृतः. **2** वल्लूरं-रः. **3** मंदिरः.

Hamadryad, *s.* वन-तरु-देवता.

Hamlet, *s.* ग्रामः, क्षुद्रग्रामः, कुग्रामः, पल्लि-ल्ली *f.*

Hammer, *s.* मुद्गरः, घनः, अयोघनः, द्रुघणः-नः. **-***v. t.* बलेन-ताडनेन-प्रविश् *c.* **2** मुद्गरेण तड् 10 or प्र-हृ 1 P. **-***v. i.* सोद्योगं यत् 1 A or परिश्रम् 4 P. **-ing,** *s.* मुद्गराघातः.

Hammock, *s.* प्रेंख, दोला, प्रेंखोलनं.

Hamper, *s.* पेटिका, पेटकः, करंडः, पिटः, कंडोलः. **-***v. t.* प्रति-नि-वि-रुध् 7 U, प्रति-वि-हन् 2 P, कुंठ् 10, बाध् 1 A, विघ्नयति (D.), स्तंभ् 9 P, प्रतिबंध् 9 P. **-ed,** *a.* कुंठित-निरुद्ध-गति, प्रतिहत, निरुद्ध, बाधित, कुंठित, प्रतिबद्ध.

Hamstring, *s.* मंदिराशिरा.

Hand, *s.* हस्तः, पाणिः, करः, शयः, पंचशाखः, भुजादलः. **2** पार्श्वः, भागः, पक्षः. **3** करणं, विधानं, चेष्टा, क्रिया, व्यापारः. **4** वशः-शं, अधिकारः, शक्ति *f.*, प्रभुत्वं. **5** कर्तृ *m.*, कारः-कारकः in comp.; कर्मकरः. **6** प्रदेशिनी, सूचिनी; कीलः; सूचि *f.* **7** लिपि *f.*, लिबि *f.*, अक्षरसंस्थानं, लिखितं; 'h. to hand' हस्ताहस्ति, बाहूबाहवि, मुष्टीमुष्टि; 'h. to h. fight' नियुद्धं, बाहुयुद्धं; 'on the one h.-on the other h.' एकतः-अन्यतः, इतः-इतः, एकंच-अपरंच; oft. by च-च; 'on the other h.' विपर्यये, प्रत्युत, तु, तावत्; 'if on the other h.' अथ, यदि; 'on all h. s' सर्वथा, सर्वत्र; 'at h.' प्रत्यासन्न, समीपवर्तिन्, आसन्न, संनिहित, समीपं-पे; 'in h.' हस्ते, हस्तगत, हस्तवर्तिन्, करतलगत; 'subject in h.' प्रकृतं, प्रस्तुतं; 'h. in h.' एकत्र, समवायसंबंधेन; सह, सहितं, समं, संभूय; 'to give a helping h.' हस्तावलंबं दा 3 U; 'given a helping h.' दत्तहस्तावलंब, 'living from h. to mouth' उत्पन्नभोजिन्; दुर्गत, कृच्छ्रगत; 'on h.' अनुपयुक्त, अव्यापृत; (of books &c.) अविक्रीत; 'sword in h.' खड्गहस्त, कृपाणपाणि; 'off-h.' आशु, अविचार्य, अविलंबं; आकस्मिक-प्रत्युत्पन्न-अचिंतितपूर्व- *a.* 'out of h.' सपदि, तत्क्षणात्; 'to take in h.' आरभ् 1 A, प्रस्तु 2 U, उपक्रम् 1 A: lend a h. उपकृ 8 U, अनुग्रह् 9 P, साहाय्यं कृ; 'lay h. s on' धृ 1 P, ग्रह्, आधृष् c., परामृश्-स्पृश् 6 P. 'to have a h. in' सहकारिन् *a.* भू, सहायः भू; 'have or get the upper h.' अभि-भू, प्र-भू, अतिरिच् pass; 'under-h.' निंद्य, छलेन, सकपट; 'clap the h. s' करतालं वद् c.; 'to support with the h.' करेण अव-आ-लंब् 1 A, हस्तावलंबं दा; 'the open or extended h.' चपेटः, चर्पटः, प्रहस्तः, प्रतलः; 'hollow of the h.' करपुटं, हस्तकोषः; 'two open h.-s joined together' संहततलः, प्रतलः; 'folded h.' प्रसृतिः; 'folded h. s joined' अंजलिः; 'clenched h.' मुष्टि *m. f.*: 'h. with the fist clenched' रत्निः. **-***v. i.* हस्ते-करे-निक्षिप् 6 P or दा 3 U or ऋ *c.* (अर्पयति); 'h. down' परंपरया-क्रमेण-संचर् *c.* or संक्रम् *c.*; 'to be h. ed down' परंपरया आगम् 1 P; उप-, संक्रम् 1 U, 4 P, (यानि भगवतःकृशाश्वात्कौशिकमृषिमुपसंक्रांतानि U 1.); (in sacred texts) आ-समा-म्ना pass.; 'h.-book' हस्तनेयं पुस्तकं; लघुग्रंथः; 'h.-cuff' हस्तपाशः-निगडः, करबंधनं; (*v. t.*) पाशेन हस्तौ बंध् 9 P or संयम् 1 P or यंत्र् 10: 'h.-kerchief' करवस्त्रं; 'h.-maid' चेटी, दासी, परिचारिका; 'h. mill' हस्तचालिता पेषणी; 'h.- weapon' हस्तायुधं, करशस्त्रं; 'h.-writing' लिखितं, लिपि-बि *f.*, अक्षरसंस्थानं; 'one's own h.-writing' हस्तलेखः, स्वहस्ताक्षरं. **-ful,** *s.* मुष्टि *m. f.*; 'a h. of grass' तृणमुष्टिः. **2** अल्प-स्तोक-संख्या, oft. by अल्प-स्तोक-*a.* **-Handicraft,** *s.* शिल्पं, हस्तलाघवं, हस्तशिल्पं-कर्मन् *n.* शिल्पविद्या; 'h. s-man' शिल्पिन् *m.*, शिल्पकारः, कर्मकरः. **-Handiwork,** *s.* हस्तकृतं कर्म. **—Handy,** *a.* दक्ष, लघुहस्त, करदक्ष, सुप्रयोगवत्, कुशल, निपुण, चतुर, पटु, क्षिप्रकारिन्. **2** सुखनेय, लघुभार-अनुवह. **3** आसन्न, निकट, प्रत्युत्पन्न. **-ly,** *adv.* हस्तलाघवेन, दक्षतया, सपाटवं, युक्त्या, चतुरं, दाक्ष्येण. **-ness,** *s.* दक्षता, हस्तलाघवं, करदक्षता, कौशलं, चातुर्यं, नैपुण्यं.

Handle, *s* मुष्टि *m. f.*, दंडः, कर्णः, वारंगः, त्सरुः-रुं. **2** (Of swords) त्सरुः, सरुः. **3** (Of ploughs) ईषादंडः; 'to give h.' अवसरं-अवकाशं-दा 3 U; 'serve as a h.'

उपकरणीभू 1 P. -*v. t.* (A subject) **वि-चर् c., विमृश् 6 P, निरूप् 10, परीक्ष् 1 A, पर्यालोच् 10**; *See* **Examine. 2 प्रयुज् 7 A,** 10; **वृत्** 1 A, **व्यव-हृ** 1 P, **आचर्** 1 P (with loc.). *3* **प्र-णी** 1 P, **वि-धा** 3 U, **निर्वह्** c. **4** हस्तेन स्पृश्-परामृश् 6 P or आ-समा-लभ् 1 A.

Handsel, *s.* प्रथमव्यवहारः-विक्रयः.

Handsome, *a.* कांतिमत्, सुंदर (री *f.*), रूप-वत्, सुरूप, चारु, शुभ, शोभन, कांत, वाम, सुगात्र (त्री *f.*), सुदृश्य, सु in comp.; *See* **Beautiful, 2** विपुल, यथेष्ट, प्रचुर. 3 उदार, वदान्य, स्थूललक्ष्य ; ' h. is that h. does ' आचारसौष्ठवमेव परमार्थतः सौष्ठवमित्युच्यते. **-ly,** *adv.* चारुतया, शोभनं, सु pr. **-ness,** *s.* कांति *f.*, रूपं, लावण्यं, शोभा.

Hang, *v. t.* बंध् 9 P, नि-धा 3 U, अनु-वि-संज् (षंज्) 1 P, आ-अव-लंब् c , आंदोल-यति (D.). ' hung by a loop ' काचित, शिक्यित. **2** उद्-बंध्, उद्बध्य व्या-पद् c. or हन् c. (घातयति). **3** आ- अव-नम् c. (नम-यति), नम् c., नम्रीकृ 8 U, नम्रतां नी 1 P; *See* **Bend;** ' with his lotuslike face hung down ' अवनतमुखपुंडरीकः; ' h.-ing the head ' अवनतमुख-शिरस्, नतमूर्धन्. **4** आच्छद् 10, वि- भूष् 10, प्र-साध् c., मंड् 10, अलंकृ 8 U, परिष्कृ. -*v. i.* प्र-अव-लंब् 1 A, लुल् 1 P, लुठ् 6 P, 1 A, चंच् 1 P, दोला-यते (D.), प्रेंख् 1 P, उद्-बंध् pass.; ' h. between ' त्रिशंकुरिवांतरा तिष्ठ (S. 2). **2** (Stick) आसंज् pass., लग् 1 P, अनुबंध् pass., संलग्नीभू 1 P. **3** (On, upon) अव-लंब्, आ-श्रि 1 U, उप-अनु-जीव् 1 P: *See* **Depend;** ' thereby h. s a tale ' तदनु-विद्धा काचिदाख्यायिका वर्तते; ' h. over ' उत्क्रम् 1 P, उप-स्था 1 U, प्रत्यासद् 1 P. **-er,** *s.* उद्बंधकः; ' h. on ' आश्रितः, पादसेविन् *m.*, पीठमर्दः, अनु-उप-जीविन् *m.*, पराधीनः, परपिंडादः. **-ing,** *s.* उद्बंधनं. **2** परिच्छदः, वसनं; जवनिका, प्रच्छदपटः, चित्रयवनिका. **-Hangman,** *s.* घातकः, दंडपाशिकः, वध्या-पुरुषः.

Hank, *s.* काष्ठवलयः. **Cheat,** q. v.

Hanker, *v. i.* अभिलष् 1, 4 P, स्पृह् 10, वांछ् 1 P, उत्कंठ् 1 A; लुभ् 4 P; *See* **Long;** oft. by उत्क, उत्सुक, पर्युत्सुक, पर, तत्पर, परायण, in comp. **-ing,** *s.* अति-स्पृहा, उत्कंठा, औत्सुक्यं, अत्यभिलाषः.

Hap, *s.* दैवं, दैवयोगः-घटना, यदृच्छा. **-less,** *a.* अधन्य, मंदभाग्य, दुर्दैव. **-ly,** *adv.* दैवात्, दैवयोगात्, दैववशात्.

Haphazard, *a.* असमीक्ष्य, अविचार्य; दैवा-यत्त, दैवाधीन

Happen, *v. i.* **वृत्** 1 A, **भू** 1 P, **घट्** 1 A; **संवृत्, सं-भू, स-समा-पद् 4 A, स्था 1 P, आ-** सं-पत् 1 P, प्रसंज् pass. **2** अकस्मात्, यदृ-च्छया, दैवात्, दैववशात् with verbs; *See* **Chance.**

Happy, *a.* सुखिन्, प्रीत, हृष्ट, सानंद, सुखित, सुखभाज्, प्रमुदित, आह्लत्त, निर्वृत, निश्चिंत, तृप्त, संतुष्ट. **2** भाग्यवत्, शुभान्वित, शुभंयु, समृद्ध, श्रीमत्, निरापद्, कुशलिन् निर्वृतिमत्, क्षेम; धन्य, कृतिन्, कृतार्थ; 'h. is it for me that &c.' इदमेव तावन्मम परमभाग्यं मन्ये. **3** शुभ, शिव, कल्याण (णी *f.*), मंगल, पुण्य, भद्र, भव्य, आनंदप्रद, भावुक, प्रशस्त; ' a h. result ' सुफलं, कल्याणोदर्कः. **-ly,** *adv.* सुखेन, सुखं, निर्विघ्नं, स्वास्थ्येन, यथासुखं. **2** दिष्ट्या, दैवात्, अकस्मात्, यदृच्छया, दैव-वशात्, सौभाग्येन, पुण्योदयात्. **-ness,** *s.* सुखं, सौख्यं, आनंदः, धन्यता, हर्षः, कृतार्थता शर्मन् *n.*, संतोषः, निर्वृति *f.*, श्रीः, संपद् *f.*, पुण्योदयः. **2** कल्याणं, भद्रं, क्षेमः-मं, शिवं, स्वास्थ्यं, कुशलं.

Harangue, *s.* उच्चैः वचस् *n.*, तारस्वरेण भाषणं, सालंकारं वचनं. -*v. i.* सालंकारं-सदर्प-वद् 1 P or भाष् 1 A. **-er,** *s.* वागीशः, प्रवचनपटुः, वाक्पटुः.

Harass, *v. t.* अर्द् 1 P or c., व्यथ् c. (व्यथ-यति), पीड् 10, क्लिश् 9 P, दु 5 P, सं-परि-तप् c., उपहन् 2 P, विप्रकृ 8 U, निकृ, उपप्लु 1 A, बाध् 1 A, प्रतिरुध् 7 U. **2** खिद् c., श्रम् c. क्लम् c., आयस् c., ग्लै c. (ग्ल-ग्ला-पयति). **-er,** *s.* पीडकः, उपप्लावकः, खेदकः, आयासकः. **-ing,** *a.* दुःख-क्लेश-कर (री *f.*), पीडाप्रद, क्लेशावह.

Harbinger, *s.* अग्रे(ग्र)सरः, अग्रदूतः, अग्र-पुरोगः-गामिन् *m.* वार्ताहरः, संदेशहरः (of news): ' h. of spring ' वसंताग्रदूतः; ' antecedent good omens are the h. s of the coming happiness ' आवेदयंति प्रत्यासन्नमानंदं अग्रजातानि शु-भानि निमित्तानि (Ka. 65).

Harbour, *s.* खातं, क्रोडः, नौकाश्रयः **2** शरणं, गति *f.*, आश्रयः, संश्रयः, अवकाशः, वासस्थानं. -*v. t.* वस् c., आश्रयं-वासस्थानं-दा 3 U, सत्कृ 8 U. **2** धृ 1 P, 10, मनसि कृ or उपलभ् 1 A or ग्रह् 9 U or नि-धा 3 U. **3** आश्रि 1 U, निवस् 1 P. **-age,** *s.* आश्रयः; *See* (*s.*). **-less,** *a.* निराश्रय, अगतिक, अशरण.

Hard, *a.* दृढ, घन, संहत, कठिन, दृढसंधि, कठोर, कर्कश, कीकस; ' becoming h. (solid) ' कठिनतामापद्यमान. **2** उग्र, दारुण; निर्घृण, निर्दय, क्रूर, नृशंस, निष्ठुर, कठोर; ' oh h. fate ' अहो दारुणो दैव-दुर्विपाकः, अहो वामता-वक्रता-विधेः, अहो वक्रं विधेः कीडितं. **3** (Lesson) दुर्बोध, असुगम, दुर्ज्ञेय, गहन. **4** क्लेशावह, दुःखद,

व्यथा-पीडा-कर (री *f.*), क्लेशिन. 5 (Sound) कर्कश, कठोर, रूक्ष, परुष. 6 अननुकूल, वाम, विरुद्ध, प्रतिकूल, प्रतीप, वक्र. 7 असुकर, दुष्कर, कष्ट, दुःसाध्य, कठिण, दुर्-दुःख-कष्ट in comp.: *See* **Difficult.** 8 शुक्त, अम्ल. *-adv.* प्रयत्नतः, आयासेन, सोद्योगं, बलेन, बलवत्, सोत्साहं, प्रसभं, तीक्ष्णं, समयत्नं, सोद्यमं. 2 दुःखेन, कष्टेन, कृच्छ्रेण, प्रयासेन, दुर् pr. 3 त्वरितं, शीघ्रं; 'h.-pressed by hunger' क्षुधया नितरां-बलवत्-पीडित, प्रबलक्षुधावसन्न; 'b. by' समीपे-पं, अनतिदूरं-रे, निकटं-टे, उपांते, आरात्; 'h.-drinker' पानरतः, अतिपानासक्तः; 'h.-earned' कष्टोपार्जित, श्रमेण लब्ध; 'h.-featured' दुर्मुख. कदाकार; 'h.-fisted' दृढ-बद्ध-मुष्टि. असुक्तहस्त, व्ययपराङ्मुख; 'h.-hearted' कठोर, नृशंस, क्रूर, निर्दय, निर्घृण, कठोर-कठिण-हृदय, पाषाण-वज्र-हृदय, अयोहृदय, वज्रमय (यी *f.*), निरनुक्रोश; 'h.-ware लोहभांडानि (pl.). **-en,** *v. t.* कठिनीकृ 8 U, दृढीकृ, घनीकृ, कृ with (*a.*). **-ly,** *adv.* कथं कथमपि, कष्टेन, दुःखेन, कष्टं कृच्छ्रेण, नैव. **-ness,** *s.* काठिन्यं, दृढता, कठोरता, निष्ठुरता, दुर्बोधता, दुष्करत्वं, उग्रता, &c. **-ship,** *s.* कष्टः-ष्टं, क्लेशः, दुःखं, पीडा, बाधा, काय-देह-क्लेशः; कृच्छ्रं, आयासः, खेदः. **-Hardy,** *a.* साहसिन्, प्रगल्भ, शूर, वीर, धीर, निर्भय, प्रतिभानवत्, साहसिक (की *f.*). विक्रांत, निःशंक. 2 दृढ or कठिन-देह-शरीर-काय; 'of a h. frame सिंहसंहनन; वज्रदेह. **-hood,** *s.* वीर्यं, शौर्यं, साहसिकता, प्रागल्भ्यं साहसं; धृष्टता, प्रतिभा, निर्लज्जता. **-ness,** शौर्यं, वीर्यं, देहकाठिन्यं.

Hare, *s.* शशः, शशकः; 'h.-brained' अविमृश्यकारिन्, चपलबुद्धि, भ्रांतचित्त, साहसपर.

Harem, *s.* अवरोधः-धनं, शुद्धांतः, अंतःपुरं, अवरोधगृहं, स्त्रीगृहं; 'women of the h.' अवरोधः, परिग्रहः, अंतःपुरं.

Hark, *interj.* ननु, शृणु, आकर्णय, अवधीयतां.

Harlequin, *s.* वैहासिकः, भंडः, विदूषकः.

Harlot, *s.* वेश्या, पण्यस्त्री, वार-स्त्री-योषित्-योषा, पण्यांगना, गणिका, वारांगना, रूपाजीवा; बंधकी, पुंश्चली, कुलटा. **-ry,** *s.* वेश्यावृत्ति *f.*, वेश्यासेवा.

Harm, *s.* क्षति *f.*, हिंसा, अपायः, नाशः, पीडा, बाधा, अपचयः, अपकृति *f.*, विरोधः, अपकारः, हानि *f.*, उपद्रवः. 2 दोषः, अपराधः, पापं, नियमव्यतिक्रमः. *-v. t.* वृ 5 P, क्लिश् 9 P. अर्द् 1 P or c., हिंस् 7 P, उपद्रु 1 P, पीड् 10, बाध् 1 A, अपकृ 8 U, उपहन् 2 P, द्रुह् 4 P (with dat.), क्षण् 1 P, वि-प्र-कृ. **-ful,** *a.* हिंस्र, अपकारिन्, उपद्रविन्, हिंसक, अपकारक, हिंसात्मक, क्षतिकारक; घातुक, शरारु, शारुक (animals). **-less,** *a.* अनपकारिन्, अहिंस्र, निरुपद्रव, अहिंसक, अघातुक. 2 निर्दोष, निरपराध, निष्पाप. **-lessness,** *s.* अहिंसा, अद्रोहः, अनपकारः, हिंसात्यागः. 2 निरपराधता.

Harmony, *s.* तालैक्यं, स्वरैक्यं, स्वरसंगः, एकतालः-नः; 'the triple h.' तौर्यत्रिकं. 2 कलता, सुश्राव्यता, स्वरमाधुर्यं, सुस्वरता. 3 संवादः, अविरोधः, ऐक्यं, एकता, संगः, संयोगः, आनुरूप्यं, सादृश्यं; 'h. of thought or mind' चित्तैक्यं, संमति *f.*, एकचित्तता, मतसंवादः. 4 स्नेहभावः, प्रीति *f.*, मैत्र्यं, स्नेहः. **-ic, -ical,** *a.* एकताल-न, समएकस्वर, सुस्वर. **-ize,** *v. t.* सदृशीकृ 8 U. 2 स्वरैक्यं-तालैक्यं-उत्पद् c. *-v. i.* सदृशीभू 1 P, एकी-तुल्यी-भू, सं-वद् 1 P, न विरुध् pass. **-ous,** *a.* एकताल-न, एक-सम-स्वर, एकस्वन, संगतस्वर-स्वन, एकलय. 2 मधुरस्वर-स्वन, सुस्वर, सुखश्रव, श्रोत्राभिराम, सुश्राव्य, श्रुतिसुख, कल, श्रवणसुभग. 3 संवादिन्, सदृश (शी *f.*), अविरुद्ध, अनुगुण, अनुरूप. **-ously,** *adv.* एकस्वरेण-स्वनेन. 2 मधुरस्वरेण-स्वनेन, कलं, मधुरं, सुस्वरं. 3 चित्तैक्येन, अविरोधेन.

Harness, *v. t.* सज्जीकृ 8 U, सन्नह् 4 P or c., सज्ज *a.* कृ. 2 (रथे) युज् 7 U, 10, नि-आ-सम्°. *-s.* सज्जा, सन्नाहः, प्रसाधनं, पर्यच्छदः, आभरणं. 2 अश्वसज्जा.

Harp, *s.* वल्लकी, वीणा, सारंगी, विपंची. *-v. i.* वीणां वद् c., 'praise by h.-ing' उपवीणयति (D.); 'h. on' पुनरुक्त्या-पौनःपुन्येन-वद् 1 P, प्रपंचयति (D.). **-er,** *s.* वीणावादकः.

Harpoon, *s.* तिमिवेधनी. **-er,** *s.* तिमिवेधकः.

Harpy, *s.* राक्षसी.

Harridan, *s.* वृद्धवेश्या, जरती गणिका.

Harrow, *v. t.* अत्यंतं पीड् 10 or तुद् 6 P. संतप् c., प्रबाध् 1 A. *See* **Grieve.** 2 लोष्टानि भिद् 7 P or विद् 10 *-s.* कोटि(टी)-शः, लोष्टभेदनः. **-ing,** *a.* हृदय-मर्म-च्छिद्र, अरुंतुद, हृदिस्पृश्, अतिदुःखावह.

Harry, *See* **Harass.**

Harsh, *a.* कर्कश, परुष, रूक्ष, निष्ठुर, कठोर, उग्र, कठिन, क्रूर, कटु; 'h. to the touch' असमृण, दुःखस्पर्श, रूक्ष; 'h. to the taste' शुक्त, कषाय; 'h. to the ear' विस्वर, कर्णकटु, दुःश्राव्य, परुष, कर्कश. **-ly,** *adv.* निष्ठुरं, परुषं, रूक्षं; क्रौर्येण, उग्रं. **-ness,** *s.* पारुष्यं, कार्कश्यं, रूक्षता, काठिन्यं.

Harslet, *s.* शूकरांत्राणि (pl.).

Hart, *s.* मृगः, हरिणः, एणः, कुरंगः-गमः.

Harum-scarum, *a.* प्रमादिन्, असावधान, साहसिन्.

Harvest, *s.* लवः, शस्यसंग्रहकालः, शस्यलवन-संचय-समयः. 2 शस्यानि, संगृहीत-लून-शस्यं. -*v. t.* शस्यं लू 9 U or संग्रह् 9 P or संचि 5 U; 'h.-lord' प्रधानः शस्यसंग्राहकः; 'h.-man' शस्यसंग्राहकः-छेत् *m.*

Hash, *See* **Hack.**

Haste, *s.* त्वरा, वेगः, जवः, तूर्णि *f.*, संभ्रमः, शीघ्रता, क्षिप्रता, तरस् *n.*, रभसः-सं, त्वरित-आशु-गति *f.*-गमनं. -*v. i.*, **-en,** 'make h.' त्वर् 1 A, सत्वरं-आशु-गम् or चल् or धाव् 1 P; 'h. towards' अभिद्रु 1 P. -*v. t.*, **-en,** त्वर् c. (त्वरयति). **-Hasty,** *a.* सत्वर, त्वरित, क्षिप्र, तूर्ण, शीघ्र, त्वरावत्, द्रुत, अविलंबिन्, आशुकारिन्. 2 साहसिन्, अविमृश्य-असमीक्ष्य-कारिन् or-कृत्. 3 शीघ्र-कोपिन्, तुलभकोप. **-Hastily,** *adv.* शीघ्रं, क्षिप्रं, सत्वरं, अविलंबं, त्वरितं, आशु, झटिति, द्रुतं. 2 सहसा, सरभसं, ससंभ्रमं, वेगेन 3 कोपेन, सरभसं.

Hat, *s.* शिरस्त्राणं, मस्तकावेष्टनं, शिरोभूषणं.

Hatch, *v. t.* उत्पद् c., उद्भू c., जन् c., निर्गम् c. 2 घट् c. (घटयति), चिंत् 10, निरूप् 10; *See* **Contrive.** -*s.* पक्षिशावक-गणः. 2 चिंतनं, घटनं-ना. 3 नौमुखं.

Hatchel, *s.* अतसीमार्जनी-शोधनी.

Hatchet, *s.* परशुः, कुठारः; वृक्षादनी, परश्वधः, वृक्षभेदिन् *m.*; 'h. for cutting stones' टं(तं)-कः, पाषाणदारणः.

Hate, *v. t.* वि-, द्विष् 2 U, गुप् desid. (जुगुप्सते) (with abl.), गर्ह् 1, 10 A, वि-प्र-°, कुत्स् 10 A, द्रुह् 4 P (with dat.), अभि-द्रुह् (with acc.). -*s.*, **-Hatred,** *s.* वि-द्वेषः, जुगुप्सा, गर्हा, कुत्सा, घृणा, अप्रीति *f.* **-er,** *s.* द्वेष्टृ *m.*, द्विष्-द्वेषिन् *m.*, द्वेषणः. **-ful,** *a.* विद्विष्ट, गर्हित, घृणार्ह, गर्ह्य, विद्वेष्य, अक्षिगत, कुत्सित.

Haughty, *a.* उद्धत, उत्सिक्त, मत्त, सगर्व, गर्वित, मानिन्, मानवत्, दृप्त, सदर्प, साटोप, साहंकार, अवलिप्त, मदोद्धत, मदोदग्र; 'to be h.' दृप् 4 P. **-ly,** *adv.* सगर्वं, सदर्पं, सावलेपं, उद्धतं. **-ness,** *s.* उत्सेकः, दर्पः, औद्धत्यं, गर्वः, मदः, अहंकारः, अवलेपः, मानः, अभिमानः, आटोपः, प्रागल्भ्यं.

Haul, *v. t.* कृष् 1 P, हृ 1 P, आनी c. -*s.* आकर्षः, हरणं.

Haulm, Haum, *s.* पलालः-लं

Haunch, *s.* जघनं, नितंबः, कटि-टी *f.*, प्रोथः, श्रोणि-णी *f.* 2 उत्संगः, अंकः.

Haunt, *v. t.* सदा-नित्यशः (Frequently, q. v.) आ-श्रि 1 U or सेव् 1 A or अभि-गम् 1 P; जुष् 6 A, उपसृज् pass.; आक्रम् 1 U, 4 P; 'h. ed by devils' भूतोपसृष्ट, पिशाचसेवित-जुष्ट. -*s.* नित्यस्थानं, नित्याग मनस्थानं; आश्रयः, निलयः.

Hauteur, *s.* दर्पः, गर्वः, आटोपः, *See* **Haughtiness.**

Have, *v. t.* ex. by भू 1 P, अस् 2 P, वृत् 1 A, विद् 4 A (with gen. of possessor); धृ 1 P, 10, धा 3 U, भृ 3 U; 'I h. two sons' मम पुत्रौ स्तः-विद्येते, &c.; 'he had many sons by Gangā' गंगायां स बहून् पुत्रानुदपादयत्. 2 (With inf.) by pot. pass. part.; 'I h. to go' मया गंतव्यं. 3 प्राप् 5 P, लभ् 1 A, आ-सद् c.; *See* **Get,** 'h. one's own way' स्वातंत्र्यमवलंब् 1 A, यथाकामं-स्वेच्छया-वृत्, कामचारिन् *a.* भू 4 (Make) Ex. by causal of verbs; 'I would h. you go' त्वं गच्छेरित्यहमिच्छामि or त्वां गमयेयं. **-ing,** *a.* ex. by the terminations वत्, मत्, मिन्, इन्, विन्, वल, &c. or by उपेत, धारिन्, युक्त, अन्वित, सनाथ, उपपन्न, भृत् in comp.; or by Bah. comp.; 'h. three eyes' त्रिलोचनः; धनवत्, रजस्वल, गुणोपेत, &c. -*s.* भोगः, भुक्ति *f.*, स्वत्वं, सत्ता, अधिकारः, वशः-शं, धरणं.

Haven, *See* **Harbour.**

Havoc, *s.* प्रमाथः, निर्दलनं, निर्मथनं, विनाशः, वि-प्र-ध्वंसः, संहारः, उच्छेदः, महाप्रलयः, महाविप्लवः, संक्षयः. -*v. t.* उच्छिद् 7 P; *See* **Destroy.**

Hawk, *s.* श्येनः, पत्रिन् *m.*, शशादनः, 'कपोतारिः, खगांतकः, 'h.-eyed' सूक्ष्म-दूर-दृष्टि. 2 उत्कासनं, श्लेष्मोत्क्षेपः. -*v. i.* उत्कास् 1 A, श्लेष्माणं उत्क्षिप् 6 P. 2 पक्षिणः ग्रह् 9 U or धृ 1 P. -*v. t.* घोषणापूर्वं विक्री 9 A. **-er,** *s.* श्येनपालकः-पोषकः.

Hay, *s.* शुष्कतृणं-शष्पं-घासः; 'make h. while the sun shines' अनुकूलेऽवसरे स्वकार्यसिद्धिं कुरु or इष्टसिद्धिं संपादय; 'h.-cock or-stack' शुष्कतृणराशिः- उत्करः-चिति *f.*; 'h.-market' तृणविक्रयस्थानं.

Hazard, *s.* संकटं, संशयः, शंका, संदेहः, विकल्पः. 2 दैवं, दैवयोगः-घटना, दैवगति *f.*; 'h. of life' जीवितसंशयः; 'at any h.' समुपस्थितेपि संशये. -*v. t.* संकटे-संशये-नि-क्षिप् 6 P or पत् c., संशयस्थ-संदेहदोलास्थ-दैवाधीन-*a.* कृ 8 U, 'he who h. s his life' संशयितजीवितः **-ous,** *a.* संदिग्ध, संशयस्थ, संशयाक्रांत, सांशयिक (की *f.*),ससंदेह, दैवाधीन, दैववशग; 'a h. position' संशयस्थानं, शंकास्पदं.

Haze, *s.* धूमिका, कुज्झटिका, कुहेडिका. **-Hazy,** *a.* सधूमिक, सांधकार, साभ्र, कुज्झटिकाच्छन्न. 2 अस्पष्ट, अव्यक्त; संकुल, संकीर्ण.

Hazel, *a.* ईषत्कापिशवर्ण, आताम्र.

He, *pron.* सः, एषः, असौ, अयं.

Head, *s.* शिरस् *n.*, शीर्षं, शीर्षकं, मूर्धन् *m.*, मस्तकः-कं, मौलि *m. f.*, वरांगं, उत्तमांगं, मुंडः-डं. 2 अग्रणीः, अध्यक्षः, धौरेयः, धुर्यः, धूर्वहः, धुरीणः, पुरोगः, पतिः, नायकः, अधिपः-पतिः, मुखरः, श्रेष्ठः, अधिष्ठातृ *m.*, मुख्य-प्रधान in comp. 3 विषयः, पदं, स्थानं, अधिकरणं. 4 अग्रं, शिरस्, चूडा, शिखरं. 5 मूलं, प्रभवः, उद्गमः, उद्भवः, आदिहेतुः. 6 मति *f.*, बुद्धि *f.* धीः; 'to be placed at the h. of' धुरि कीर्तनीय-or प्रतिष्ठापयितव्य-*a.*; 'h. merchant' श्रेष्ठिन् *m.*, विट्पतिः; 'the h. of a family कुलपतिः, कुटुंबभारवाहकः; 'at the h.' ex. by आदि-प्रमुख in comp. or धुरि-मूर्ध्नि-स्था, &c.; 'with Indra at their h.' इंद्रादयः- इंद्रप्रमुखाः (देवाः); 'he stands at the h. of all' स सर्वेषां धुरि मूर्ध्नि-तिष्ठति; 'h. over ears in debt' ऋणराशौ निमग्नः or ऋणग्रस्तः; 'to get a-h. of' अतिक्रम् 1 U, 4 P, अतिरिच् pass., अभिभू; 'make h. against' प्रत्यवस्था 1 A, विरुध् 7 U, प्रतिकूलयति (D.). —*v. t.* नी 1 P, अधिष्ठा 1 P, अग्रे-मूर्ध्नि-पुरः-गम् or स्था 1 P; 'h. ed by Vasishtha' वशिष्ठाधिष्ठिताः; gen. ex. by प्रमुख-पुरोग-पुरस्सर- in comp.; 'h.-ache' शिरोवेदना, शीर्षव्यथा-पीडा, शिरः-शूलं-रोगः; *See* **Ache;** 'h.-band' शिरोवेष्टनं-बंधनं, ललाटपट्टः; 'h.-dress' शिरोभूषणं, किरीटः-टं, मुकुटं; 'h.-land' अंतरीपः-पं, भूशिरः, भूनासिका; 'h.-long or 'h. foremost' अवाक्शिरस्, अधोमुख-अवाङ्मुख (खी *f.*), अवाच्, साहसिक, सरभस, साहसिन्, क्षिप्र-अविमृश्य-कारिन्-कृत; प्रवण, पातुक, पतयालु; (*adv.*) अवाक्, अधोमुखेन, सोत्तापं, सवेगं; 'h.-most' अग्र्य, प्राग्र्य प्रमुख, मुख्य, वर, वरेण्य, उत्तम, प्रधान, in comp.; 'h.-piece' शिरस्त्रं, शिरस्त्राणं, शिरस्कं; 'h.s-man' घातकः, वधाधिकृतः, वध्यापुरुषः, मृतपाः; 'h.-strong' दुर्दांत, अप्रतिविधेय, अवश्य, दुर्दम, उच्छृंखल, अविधेय, प्रमत्त, अस्थिर, चंचल. **-less,** *a.* मस्तकहीन, अशिरस्. **-y,** *a.* साहसिन्, साहसिक, क्षिप्रकारिन्. 2 संरंभिन्, शाघ्र-सुलभ-कोप, अमर्षण.

Heal, *v. t.* शम् c. (शमयति), साध् c., समुत्था c. (समुत्थापयति), व्याधेः मुच् c.; *See* **Cure;** 'to h. a wound' व्रणं वि-रुह् c. (रोपयति); sore-h.-ing oil' व्रणाविरोपणं तैलं (S. 4). 2 समा-सं-प्रतिसमा-धा 3 U, शम् c. —*v. i.* रुह् 1 P. 2 प्र-,शम् 4 P. **-er,** *s.* रोगहरः, चिकित्सकः. **-ing,** *s.* उप-शमः-शांति *f.*, रुक्प्रतिक्रिया, चिकित्सा, प्रतीकारः, समुत्थानं. 2 विरोपणं-रोहणं. —*a.* शांतिद, रोगहर, शांतिकर (री *f.*), विरोपण.

Health, *s.* कुशलं, अरोगः, सुस्थता, वार्त्तं, रोगाभावः, निरामयत्वं, सुस्थिति *f.*, आरोग्यं, स्वास्थ्यं, अनामयं, कल्यत्वं-ता, शरीरसुखं, अरोगिता. 2 प्रकृति *f.*, शरीरावस्था, शरीरस्थितिः-प्रकृतिः; 'of a delicate h.' प्रकृतिकोमल-दुर्बल; 'he is in good h.' सुस्थोऽसौ, कुशलमस्य. **-ful, -y,** *a.* आरोग्यवत्, अरोगिन्, नीरोग, नीरुज-ज, स्वस्थ, व्याधिरहित, निरामय, वार्त्त, सुस्थ, कल्य, कुशलिन्, निर्व्याधि; 'became as h. as before' पूर्ववत् प्रकृतिस्थः समजायत. 2 आरोग्य-सुख-कर (री *f.*), पथ्य, हित, स्वास्थ्यजनक, सुखावह. **-fulness,** *See* (*s.*).

Heap, *s.* राशिः, नि-सं-चयः; चिति *f.*, निकरः, स्तोमः, पुंजः, गणः, ओघः, संभारः; *See* **Collection.** —*v. t.* राशीकृ 8 U, सं-आ-प्र-चि 5 U, एकीकृ, समाक्षिप् 6 P, सं-भृ 3 U, पिंडीकृ आ-समा-स्तृ 5 U: *See* **Collect;** 'why do you h. accusations (calumnies) upon us' किमस्मान् संभृतदोषैरधिक्षिपथ (S. 5)

Hear, *v. t.* श्रु 5 P, समा-आ-कर्ण् 10, निशम् 4 P or c. (शामयति); 'h. cases' व्यवहारान् दृश् 1 P, कार्याणि अवेक्ष् 1 A or विचर् c. or अनुसं-धा 3 U. —*v. i.* वार्तां श्रु; 'I have not heard from him for a long time' चिरं तद्वार्ता मया न श्रुता. **-er,** *s.* श्रोतृ *m.*, श्रावकः, आकर्णयितृ *m.* **-ing,** *s.* श्रवणं, श्रुति *f.* आकर्णनं, निशामनं. 2 (In law) दर्शनं, अवेक्षणं, अनुसंधानं; 'the organ of h.' श्रवणेंद्रियं, श्रोत्रं; 'within h.' श्रवणगोचरे, श्रुतिपथवर्तिन्. **-Hearsay,** *s.* जनश्रुति *f.*, कर्णपरंपरा, जनवादः-प्रवादः, किंवदंती; 'know it by h.' इति कर्णपरंपरया श्रुतं.

Hearken, *See* **Hear.**

Hearse, *s.* प्रेत-शव-यानं-वाहनं.

Heart, *s.* हृदयं, हृद् *n.* 2 (The substance) बुक्का, अग्रमांसं, बुक्काग्रमांसं. 3 (Mind) चित्तं, मनस् *n.*, चेतस् *n.*, मानसं, हृदय, अंतःकरणं, आत्मन् *m.*, अंतरात्मन् *m.*, स्वांतं. 4 उरस् *n.*, वक्षस् *n.*, वक्षःस्थलं. 5 मर्मन् *n.* 6 स्नेहः, प्रणयः, रागः, भावः. 7 उदरं, गर्भः, अभ्यंतरं, अंतर् in comp. 8 सत्त्वं, धैर्यं, पौरुषं, तेजस् *n.*; 'take h.' आ-समा-श्वस् 2 P; धैर्यं अवलंब् 1 A, अवष्टंभ् 9 P; 'learn or get by h.' कंठस्थ *a.* कृ 8 U, अभ्यस् 4 P; 'keep in the h.' चित्तेकृ, अवधृ 10; 'out of h.' दीन-खिन्न-चित्त; 'at h.' अंतः; 'with all one's h.' 'h. and soul' प्रकामं, कामं, सोत्साहं, सर्वात्मना; 'he has applied himself to the work h. and soul' सर्वात्मना तस्मिन्कर्मणि स व्यापृतः; 'to one's h.'s content' यथेच्छं, पर्याप्तं, आचित्ततोषं, कामं, प्रकामं, निकामं, इष्टं, यथेप्सितं; 'from the h.' निर्व्याजं, सोत्साहं, निर्व्यलीकं; 'h.-ache' हृदयसंतापः, मनो-

व्याधिः, हृदयव्यथा-पीडा-वेदना, मनस्तापः, मानसी व्यथा, 'h.-broken' भग्नमानस, अंतर्भिन्न, भिन्नहृदय; 'h.-burn' हृदयवेदना, मनस्तापः; हृल्लासः, अम्लपित्तं; 'h.-ease' हृदयस्वास्थ्यं-सुखं, चित्तशांति, निर्वृति *f.*; 'h.-felt' अव्याज, निर्व्याज, वास्तविक (की *f.*), अकृत्रिम; 'h.-breaking,-rending,-wounding' मर्मभिद्-स्पृश्-च्छिद्, हृदय-मर्म-भेदिन्-च्छेदिन्, हृदिस्पृश्, अरुंतुद, चित्तोद्वेगजनक; 'h.-robbing' मनोहर, चित्तहारिन्; 'h.-sick' दुर्मनस्, उद्विग्नचित्त, खिन्न-विषण्ण-हृदय; *See* **Dejected**; 'h.-struck,-wounded' विद्धमर्मन्, क्षत-विद्ध-हृदय; 'h.-whole' अक्षत-अभिन्न-हृदय. **-less,** *a.* निर्वीर्य, निस्तेजस्; भीरुहृदय, निस्सत्त्व, निष्पौरुष, क्लीब. **2** निर्दय, क्रूर, कठोरहृदय, निर्घृण. **-lessly,** *adv.* निर्वीर्यं, क्लीबवत्. **2** निर्दयं, क्रूरतया. **-lessness,** *s.* अपौरुषं, क्लीबता, निर्वीर्यत्वं. **2** निर्दयत्वं, कठोरता. **-Hearty,** *a.* सरल, निर्व्यलीक, निष्कपट, निर्व्याज, शुद्धांतःकरण; *See* **Frank. 2** अकृत्रिम, अकृतक, सोत्साह, उत्सुक, सोल्लास, सस्नेह, हृद्य; हृदयंगम, स्नेहनिर्भर; 'a h. friend' हृदयंगमः सखा. **3** वीर्यवत्, सपौरुष; कल्य, सुस्थ. **-ly,** *adv.* निर्व्यलीकं, निष्कपटं, निर्व्याजं. **2** सोल्लासं, सोत्साहं, प्रकामं, सर्वात्मना, संतुष्टचेतसा, कामतः, सानंदं, साह्लादं, चित्तसंतोषेण. **3** सवीर्यं. **-ness,** *s.* सारल्यं, अकृत्रिमता, अव्याजत्वं; उत्साहः, औत्सुक्यं, वीर्यं, तेजस् *n.*, पौरुषं.

Hearth, *s.* अग्निकुंडं, चुल्लि-ल्ली *f.*, अंतिका, अंदिका, उद्धानं, उध्मानं, अधिश्रयणी, अश्मंतं. **2** (Portable fire-place) अंगारधानिका, अंगारशकटी, हसनी, हसंती.

Heat, *v. t.* तप् c., परि-प्र-सं°; उद्-,दीप् c., ज्वल् c., संधुक्ष् 10; दह् 1 P. **-s.** तापः, सं-उत्-परि-तापः, दाहः; उष्णता, उष्मः, तिग्मता, प्रखरत्वं, ऊ-उष्मन् *m.*, चंडता. **2** आतपः, घर्मः, निदाघः; 'affected by h.' उष्णालु; 'expose to the sun's h.' सूर्यातपे दा 3 U. **3** (Summer) ग्रीष्मः, निदाघः, घर्मकालः, उष्णकालः, निदाघसमयः. **4** उत्तापः, संक्षोभः, चंडता, तीक्ष्णता, तीव्रता, उग्रता, व्यग्रता. **5** संरंभः, मदः, क्रोधः, उद्दीपनं, संधुक्षणं; आवेशः, आक्रमः; 'in the h. of excitement' रोषावेशेन. **6** कपोलरागः; 'h. of youth' यौवनगर्वः-दर्पः, यौवनोन्मादः. तारुण्यमदः. **-ing,** *s.* तापनं, दीपनं. **-***a.* तापक, दीपन.

Heath, *s.* जंगलभूमि *f.* वनभूमिः. **2** प्रचारः.

Heathen, *s.* मूर्ति-प्रतिमा-पूजकः-उपासकः-अर्चकः. **-***a.*, **-ish,** *a.* प्रतिमापूजकानुरूप. **2 Barbarous,** q. v. **-ism,** *s.* मूर्तिपूजा-अर्चनं-उपासना.

Heave, *v. t.* उन्नम् c. (नमयति), उन्नी 1 P उच्छ्रि 1 U, उद्-ह्-भृ 1 P, उद्यम् 1 A, उत्था c. (उत्थापयति), उत्क्षिप् 6 P, उत्तुल् 10 'h. a sigh' निःश्वस् 2 P, दीर्घं निःश्वस्; 'h.ing deeply' दीर्घ-स्थूलस्थूलं-निःश्वस्य. **-***v. i* स्पंद् 1 A, स्फुर् 6 P, कंप् 1 A वेप् 1 A. **2** निःश्वस्, कृच्छ्रेण उच्छ्वस्. **3** उत्सृ 1 P, प्र-लुठ् 6 P, 1 A, लुल् 1 P, तरंगायते (D.), उन्नम् 1 P. **-s.** उन्नमनं, उत्क्षेपः, उत्तोलनं, उद्धरणं. **-ing,** *s.* स्पंदनं, स्फुरणं कंपनं, वेपथुः. **2** निःश्वासः, कृच्छ्रेण उच्छ्वासः दीर्घनिश्वासः. **3** उत्सर्पणं, प्रलोठनं, लोलनं उन्नमनं. **-***a.* स्पंदमान, उत्सर्पिन्, लोल.

Heaven, *s.* दिव् *f.*, द्यो *f.*, स्वर्गः, त्रिदिवः-वं सुरलोकः, त्रिदशालयः, त्रिविष्टपं, नाकः, स्वः *ind.*; 'h. of Vishnu' वैकुंठः; 'this is a h. on earth' भूस्वर्गायमाणमेतत्स्थलं, स्थानांतरगतः स्वर्गः (V. 2). **2** आकाशः-शं, नभस् *n.*, गगनं-नं; *See* **Sky. 3 God,** q. v.; परमेश्वरः, विधिः, ईश्वरः; 'h. and earth' द्यावापृथिव्यौ, द्यावाभूमी, रोदसी-स्यौ, द्यावाक्षमे; 'h.-born' दिविज, स्वर्गीय, स्वर्गोत्पन्न. **-ly,** *a.* दिव्य, स्वर्गीय, अपार्थिव (वी *f.*), स्वर्ग्य, त्रिदिवस्थ, दिविष्ठ, 'h. body' नक्षत्रं; 'h. voice' आकाशवाणी, अशरीरिणी वाक्; 'h. nymph' सुरांगना, स्वर्योषित्, दिव्यांगना. **2** परम, उत्तम. **-wards,** *adv.* स्वर्गाभिमुखं, अभिगगनं.

Heavy, *a.* गुरु, भारवत्. **2** गाढ, दीर्घ, गुरु, तीक्ष्ण, महत् तीव्र, अत्यंत, उग्र, दारुण, उच्चंड, महा-सु-अति- in comp.; 'h. shower' महासारः, अतिवृष्टि *f.* **3** आकुल, क्षुब्ध; 'h. sea' सागरक्षोभः, क्षुब्धसागरः, ऊर्मिमालाकुलः सागरः. **4** अवसन्न, खिन्न, दीन, चिंताकुल, विषण्ण. **5** मंद, स्थूल, जड, मंथर, अलस, मंदधी-मति, जड-स्थूल-बुद्धि-धी; 'h.-headed' मंद-स्थूल-धी; 'h.-laden' गुरुभाराक्रांत, सुभारवत्. **-ly,** *adv.* गुरुभारेण, गुरुतया. **2** भृशं, तीव्रं, बलवत्, अत्यंतं, सु-अति pr.; *See* **Exceedingly. 3** सविषादं, मंदं, शनैःशनैः. **-ness,** *s.* गुरुता, गुरुत्वं, भारः, गरिमन् *m.*, विषादः, दैन्यं, मांद्यं, स्थूलता, &c.

Hebetate, *v. t. See* **Blunt, Dull.**

Hecatomb, *s.* शतबलिदानं.

Hectic, *a.* संतत, अविरत. **2** ज्वरसूचक, अंतर्दाहसूचक.

Hector, *s.* विकत्थिन् *m.*, आत्मश्लाघिन् *m.*, पिंडीशूरः, शूरंमन्यः. **2** कलहकारः, भर्त्सकः. **-***v. i.* विकत्थ् 1 A, प्रगल्भ् 1 A; *See* **Boast. 2** तर्ज्-भर्त्स् 10 A.

Hedge, *s.* वृति *f.*, प्राचीरं, प्राकारः, आवरणं, वेष्टनं, आवारः, क्षेत्रावरोधकं, क्षेत्रवेष्टनं; 'h.-born' अंत्यज, हीन-जाति-वर्ण, अधम-नीच-जातीय; 'h.-hog' शल्यः, शल्यकंठः; 'h.-

sparrow ' कलविंकः, चटकः. –v. t. वृत्या परिवेष्ट् c. or आवृ 5 U or अववृ 7 U.

Hedonic, a. सुखपर-विषयक.

Heed, v. t. आदृ 6 A, अवेक्ष् 1 A, गण् 10, मन् c., अभिनंद् 1 P; सेव् 1 A. **2** अव-धा 3 U, मनो दा 3 U, सावधान a. भू, श्रु 5 P; *See* **Hear.** –s. अवधानं,अवेक्षा, सावधानता, मनोयोगः; ' take h.' सावधानो भव. **–ful, –less,** n. *See* **Careful,–less.**

Heel, s. पार्ष्णि m. f., पादतलं-मूलं; 'to be at one's h.s' पार्ष्णिं ग्रह् 9 U, अनुसृ, पदं अनुगम् 1 P; ' I shall be close upon your h. s' अहमनुपदमागत एव (S. 3) 'to take to or show h. s ' पलाय् 1 A, अपक्रम् 1 U, 4 P; ' betake to h. s ' जंघाबलमवलंब् 1 A; ' h. s over head ' अवाक्शिरस् a., ऊर्ध्वपाद a. –v. i. एकपार्श्वे पत् 1 P or परिवृत् 1 A or प्र-लंब् 1 A.

Heft, s. उद्योगः, यत्नः, उत्साहः. **2** मुष्टि m. f., स्तवः.

Hegemony, s. नायकत्वं, आधिपत्यं.

Heifer, s. वत्सतरी, वत्सा ; ' h. one year old ' एकहायनी ; so द्विहायनी, त्रिहायणी.

Heigh-ho, *interj.* हंहो, अहो, भो भोः, रे रे.

Height, *See* under **High.**

Heinous, a. घोर, दारुण, अतिनिंद्य, गर्ह्यतम, अतिदुष्ट, महत्, अतिपापिन्, अतिघोर, पापिष्ठ. **–ly,** adv. घोरं, दारुणं. **–ness,** s. घोरता, दारुणत्वं.

Heir, s. दायादः, रिक्थहरः,अंशहरः-हारिन् m., रिक्थभागिन् m., रिक्थिन् m., धनाधिकारिन् m.,उत्तराधिकारिन् m., अंशभाक्,अंशिन् m.; '.sole h.' समग्रधनभाक्; ' h.-apparent ' युवराजः; ' h.-loom ' क्रमायातं जंगमद्रव्यं. **– .s,** s. धनाधिकारिणी, &c. **–less,** a. दायादशून्य-हीन. **–ship,** s. धनाधिकारित्वं.

Heliolatry, s. सूर्योपासना.

Heliotrope, s. सूर्यकमलं, श्रीहस्तिनी.

Hell, s. नरकः, निरयः, नारकः, दुर्गति f. **2** पातालं, रसातलं, अधोलोकः, अधोभुवनं; ' h.-tortures कारणा, यातना, तीव्रवेदना; ' river of h. ' वैतरणी. **–ish,** a. नारक (की f.), नरकीय, नारकीय (यी f.), नरकस्थ. **2 Cruel,** q. v. **3** अतिनिंद्य, दुष्टतम.

Helm, s. कर्णः, कर्णधारः-तकः, अरित्रं **2 Helmet,** q. v., ' placed at the h. of (royal) affairs ' राज्यधुरायां स्थापित. **–Helmsman,** s. कर्णधारः, नाविकः.

Helmet, s. शिरस्त्रं, शिरस्कं, शिरोभूषणं, शिरस्त्राणं, शीर्षकं पर्यं.

Help, s. साहाय्यं, उपकारः, उपकृतं-कृति f., साहित्यं, अनुग्रहः, आनुकूल्यं. **2** गति f., आश्रयः, शरणं; ' help ! help ! ' परित्रायध्वं, परित्रायध्वं. –v. t. साहाय्यं कृ 8 U, सहायः भू, अनुग्रह् 9 P, उपकृ (gen.); न हि दीपौ परस्परस्योपकुर्वातः (S. B. 420); शास्त्राणि तत्त्वज्ञानायोपकुर्वंति (S. B. 447) ' h. a right understanding'. **2** संवृध् c., प्रसृ c., पुरस्कृ, उत्तुद् 10; ' h. ed him on his legs' उत्थातुं तस्य साहाय्यं चकार; ' God h. s those who h. themselves ' दैवमुपायवत्तं, विना पुरुषकारेण दैवं न सिध्यति; दैवं पुरुषकारेण साध्यसिद्धिनिबंधनं; न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते (S. R. 104); ' can't h. ' का गतिः, किमन्यच्छरणं, 'to h. himself to a mouthful ' ग्रासग्रहणेन आत्मानं तर्पयितुं; ' a h. ing hand ' हस्तावलंबः-बनं; दैवेनेत्थं दत्तहस्तावलंबे प्रारंभे (Rat. 1); ' he could not h. laughing ' हासं निग्रहीतुं न शशाक; ' I cannot h. going ' मयावश्यं गंतव्यं; ' to h. at table ' परिविष् 10. **–er,** s. उपकारकः, उपकर्तृ m., सहायः. **–ful,** a. उपयोगिन्, सहाय, उपकारक, साहाय्यकारिन्. **–less,** a. अनाथ, निराश्रय, अगतिक, अशरण, गतिहीन, निरवलंब, असहाय. **2** अप्रतिकार्य,अपरिहार्य, अप्रतिविधेय, निरुपाय; ' we are simply h. in that matter ' तस्मिन्विषये अस्माकमन्या गतिरेव नास्ति. **–Helpmate,** s. सहधर्मिणी. **2** सहायः, सहकारिन् m.

Helve, s. वृंतः, मुष्टि m. f.

Hem, s. अंचलः, वसनप्रांतः, वस्त्रयःवृक्षाः (pl.). **2** उत्कासनं. –v. t. अंचलं सिव् 4 P. **2** (in) परिवेष्ट् 1 A or c., परि-वृ 5 U or c., निरुध् 7 U.

Hemicrania, s. अर्धावभेदकः.

Hemicycle, s. गोलार्धं.

Hemiplegy, s. पक्षाघातः, पक्षवायुः.

Hemisphere, s. गोलार्धं, अर्धगोलः.

Hemistich, s. श्लोकार्धं, अर्धश्लोकः.

Hemorrhage, s. रक्त-रुधिर-स्रावः, रक्तक्षरणं.

Hemorrhoids, s. अर्शस् n., गुदकीलः.

Hemp, s. शाणं, भंगा, मातुलानी. **–en,** a. शाण (णी f.), शाण in comp.

Hen, s. कुक्कुटी; ' h.-hearted ' भीरु, भीरुहृदय, कातर, कापुरुष; ' h.-house ' कुक्कुटपालिका; ' h.-pecked ' स्त्रीवश, स्त्रीविधेय, स्त्रीजित, स्त्रीवश्य, स्त्रीवशवर्तिन्, भार्याटिक; ' h.-roost ' कुक्कुटालयः.

Hence, adv. इतः, अस्मात् स्थानात्. **2** अतः, एतस्मात् कारणात्, तस्मात्; अत एव. **3** (From h.) अतः परं, अतः or इतः-परं or ऊर्ध्वं; अद्यप्रभृति; ' hence ! ' अपेहि, अपयाहि, अपसर; ' h.-forth,-forward ' अतः or इतः-परं or ऊर्ध्वं; अद्यप्रभृति, अद्यारभ्य, अद्यावधि.

Hepatic, a. यकृत्संबंधिन्.

Heptagon, s. सप्तभुजा-सप्तकोणा-आकृतिः.

Herald, s. घोषकः, बंदिन् m., राजदूतः. **2** (fig.) अग्रदूतः, प्रथमवार्ताहरः, अग्रेसरः. **–Heraldry,** s. वंशावलीज्ञानं.

Herb, *s.* ओषधि-धी *f.*, शाकः, शाकलता, हरितकं. **-Herbage,** *s.* तृणं, शस्यं, घासः, यवसं. **-Herbal,** *s.* वृक्षायुर्वेदः.

Herculean, *a.* भगीरथ in comp.; 'h. efforts' भगीरथप्रयत्नाः. 2 अतिप्रबल, अतिशक्तिमत्.

Herd, *s.* यूथं, गणः, संघः, वृंदं, कदंबः, कुलं, समूहः, व्रजः, निवहः; 'h. of cattle' गोकुलं, पाशवं, गोवृंदं, गोत्रा; 'h. of oxen' औक्षकं; 'h. of calves' वात्सकं; 'h. of elephants' हास्तिकं. -*v. i.* यूथेन चर् 1 P, यूथशः संमिल् 6 P or संगम् 1 A, एकीभू, एकत्र भू or मिल्. **-Herdsman,** *s.* गोरक्षकः, गोपालः, गोपः, गोधुक्, आभीरः, गोसंख्यः, वल्लवः.

Here, *adv.* अत्र, इह (gen. in this world). 2 इह लोके; ex. by demon. pron.; 'h. comes your mother' एषागच्छति ते माता; 'h. am I' अयमस्मि. -*Interj.* भो भोः; 'h. and there' इतस्ततः; अंतरांतरा, असमग्रं, असंपूर्णं; 'h. about' इतो नातिदूरे, इह समीपे; 'h.-after' इतः परं-ऊर्ध्वं, अतः, परतः, परस्तात्, अनंतरं, पश्चात्, उत्तरतः, उत्तरत्र, अग्रे, उपरिष्टात्, अतः परं; (in the next world) परत्र, अमुत्र, परलोके; (*s.*) उत्तरकालः, पर-भावि-आगामि-कालः; 'h.-at' अत्रांतरे, अथ; 'h.-by' अनेन, तस्मात्, 'h.-in' अत्र, अत्र-स्थाने-विषये; 'h.-before' इतः पूर्वं, पूर्वकाले, पुरा, प्राक्, अतीत-गत-काले; 'h.-upon' ततः, अनंतरं, तदुपरि, तच्छ्रुत्वा.

Hereditary, *a.* पितृपैतामह (ही *f.*), पित्र्य, पैतृक (की *f.*), परंपरीण-य, परंपरागत, परंपराप्राप्त, क्रमायात, क्रमागत, कुलक्रमागत, अन्वयागत; 'h. disease' संचारी रोगः; 'h. servant' मूलभृत्यः, मौलः; 'h. succession' क्रमागतत्वं. **-ly,** *adv.* कुलक्रमेण, वंशक्रमेण, परंपरया, पारंपर्येण.

Hereditament, *s.* दायः, रिक्थाधिकारः.

Heredity, *s.* पैतृक *a.* गुणः.

Heresy, *s.* पाषंडमार्गः, नास्तिकता, मिथ्यादृष्टि *f.*, विधर्मः, विधर्मसेवा, परधर्माश्रयः, अधर्मः, विपक्षः. **-Heretic,** *s.* पाषं(खं)डः, नास्तिकः, विधर्मसेविन् *m.*, परधर्मावलंबिन् *m.*, वेदनिंदकः, उपधर्मसेविन् *m.*, स्वधर्मभ्रष्टः-च्युतः, पतितः. **-al,** *a.* धर्मविरुद्ध, विपथ-विधर्मगामिन्. **-ally,** *adv.* पाषंडवत्, नास्तिकवत्.

Heritable, *a.* पितृप्राप्य, दायग्राह्य.

Heritage, *s.* दायः, पैतृकं धनं, रिक्थं, पैतृकद्रव्याधिकारः.

Hermaphrodite, *s.* स्त्रीपुरुषलक्षणान्वितः.

Hermetic,-al, *a.* रसायनीय, रसायनज. 2 सुदृढ. **-ly,** *adv.* सुदृढं, गाढं.

Hermit, *s.* यतिः, तापसः, तपस्विन् *m.*, मुनिः, आरण्यकः, वन-अरण्य-वासिन् *m.*, वानप्रस्थः, वैखानसः. **-age,** *s.* आश्रमः, उटजः-जं, पर्णशाला.

Hernia, *s.* अंत्रवृद्धि *f.*; अंत्रभ्रंशः.

Hero, *s.* वीरः, शूरः, भटः, विक्रांतपुरुषः, प्र-महा-वीरः, जेतृ *m.*, रथिन् *m.*, अतिरथः, शौंडीरः. 2 (In dramas &c.) नायकः, कथापुरुषः; 'h. es of Râmâyana' रामायणकथापुरुषाः or-नायकाः. **-ic,-ical,** *a.* वीर, शूर, प्रवीर, विक्रांत, वीर्यवत्, अमितौजस्, महावीर्य; 'a h. deed' पराक्रमः, विक्रमः, अवदातं कर्म. 2 वीरचरित्रविषयक, वीररसप्रधान. **-ically,** *adv.* सविक्रमं, सवीर्यं, शूरवत्. **-ism,** *s.* वीर्यं, शूरत्वं, शौर्यं, पराक्रमः, धामन् *n.*, ओजस् *n.*, रणोत्साहः, पौरुषं, साहसं, वीर्यवत्त्वं, शौटीर्यं. **-Heroine,** *s.* नायिका.

Heron, *s.* बकः, सारसः, लोहपृष्ठः, क्रौंचः.

Herpes, *s.* *See* **Itch.**

Hesitate, *v. i.* वि-आ-शंक् 1 A, दोलायते (D.), विचर् c., विकल्प् 1 A or c., विलंब् 1 A, चिर(रा)यति-आंदोलयति (D.); *See* **Doubt** also. 2 **Falter,** q. v. **-ingly,** *adv.* संशय्य, सविकल्पं, ससंशयं, साशंकं. 2 स्खलनपूर्वकं. **-ion,** *s.* शंका, संशयः, विकल्पः, आ-वि-परि-शंका, विचारः, संदेहः, वितर्कः, द्वापरः, अनिर्णयः, विचिकित्सा. 2 (In speaking) स्खलनं, स्वरभेदः-भंगः, स्खलद्वचनं, गद्गदवाच् *f.*

Hesperian, *a.* *See* **Western.**

Hest, *s.* *See* **Command.**

Heteroclite, *a.* विधिविरुद्ध, निपातित.

Heterodox, *a.* भिन्न-मत-धर्मन्, धर्मविरुद्ध, विपरीत, विधर्मिन्, वैधर्मिक (की *f.*), अपथवर्तिन्-गामिन्. **-y,** *s.* विधर्मः, भिन्नमतं-धर्मः,

Heterogeneous, *a.* भिन्न, विजातीय, पृथग्विध, भिन्नजातीय, विरुद्ध; *See* **Different.**

Hew, *v. t.* छिद् 7 P, कृत् 6 P, लू 9 U, *See* **Cut.** **-er,** *s.* छेदकः, छेदिन् *m.*, छिद् in comp. **-Hewn,** *a.* छिन्न, दात, वृक्ण, लून कृत्त, दित, छात.

Hexagon, *s.* षट्कोणः, षडस्रः.

Hexametre, *s.* षट्पदी-चरणः.

Hexapod, *s.* षट्पदः.

Hey, *interj.* अहो, ननु, हाहा.

Heyday, *interj.* नमः, स्वस्ति (with dat.); अहो, भोः, -*s.* उल्लासः, प्रमोदः, हर्षः, मुदा, परिहासः; 'h. of youth' नवं-प्रथमं-यौवनं.

Hiatus, *s.* भंगः, भेदः, छेदः, विच्छेदः.

Hibernal, *a.* हैमंत (ती *f.*), हैमंतिक (की *f.*). **-Hibernate,** *v. i.* शीतकालं or हेमंतं नी 1 P.

Hiccough, Hiccup, *s.* हिक्का, हिध्मा. -*v. i.* हिक्क् 1 U.

Hide, *s.* चर्मन् *n.*, अजिनं, दृतिः, कृत्ति *f.*, पशु-चर्मन् *n.*-त्वच् *f.*; 'h.-bound' दृढमुष्टि, कृपण; अवश्य, अविनय, कठोर, कठिन. —*v. t.* प्रच्छद् 10, गुह् 1 U, गुप् 1 P, अंतर्धा 3 U, तिरोधा, स्थग् 10, अपह् c.: *See* **Conceal.** —*v. i.* गुह्-गुप् pass., गुप्त-निलीन-*a.* भू 1 P, नि-ली 4 A, तिरोभू, तिरोधा pass.: 'h. s behind the bushes' विटपांतरितस्तिष्ठति-भवति. **—Hid,-Hidden,** *a.* गूढ, गुप्त, प्रच्छन्न, छादित, अतर्हित, तिरोहित, अंतरित, अपवारित, निभृत, स्थगित, लीन, निलीन. **-ing,** *s.* गोपनं, गुप्ति *f.*, प्रच्छादनं, स्थगनं, तिरोधानं; 'h.-place' निभृत-गूढ-स्थानं, गुप्तिः, निभृतं.

Hideous, *a.* बीभत्स, विकृत, घोर, भीषण, कराल, उग्रदर्शन, कराल-मुख-वदन, कद्राकार, भीम-घोर-दर्शन-आकृति, उग्र-घोर-रूप, दुर्दर्शन; 'Oh! this is indeed a h. spectacle' हंत बीभत्समेवाग्रतो वर्तते (Mal. 5). **-ly,** *adv.* उग्रं, घोररूपेण, बीभत्सं. **-ness,** *s.* घोरता, करालता, उग्रता.

Hie, *v. i.* त्वर् 1 A, सत्वरं गम् 1 P.

Hiemal, *a. See* **Hibernal.**

Hiemate, *v. i. See* **Hibernate.**

Hierarch, *s.* पुरोहितेश्वरः, आचार्येश्वरः. **-y,** *s.* आचार्याधिपत्यं, धर्माध्यापकप्रमुखत्वं.

Hieroglyph,-ic, *s.* गूढाक्षरं, बीजाक्षरं.

Hierophant, *s.* मंत्रव्याख्यातृ *m.*, आचार्यः.

Higgle, *v. i.* पण् 1 A, व्यव-ह 1 P. 2 **Haggle,** q. v.

High, *a.* उच्च, उन्नत, उच्छ्रित, समुच्छ्रित, सोच्छ्राय, तुंग, प्रांशु, उदग्र, उत्तुंग, उद्धृत, उत्तम्र, ऊर्ध्व. 2 उत्तम, विशिष्ट, मुख्य, श्रेष्ठ, परम, अग्र्य, महा-प्रधान-in comp.; *See* **Principal.** 3 प्रचंड, तीक्ष्ण, तीव्र, बलवत्, तरस्विन्, प्रबल; *See* **Strong.** 4 उदात्त, उत्ताल; 'a h. tone' उदात्तः, उच्च-तार-स्वरः, तारः. 5 (Of h. rank) विशिष्ट, उत्कृष्ट, उत्कृष्ट-विशिष्ट-पदस्थ, उत्तम-परम-पदभाज्, लब्धप्रतिष्ठ, प्रतिपत्तिमत्, सगौरव. 6 (Of h. family) कुलीन, महाकुल, अभिजात, आभिजनवत्, कुलज, महाकुलप्रसूत. 7 गर्वोद्धत, दर्पाध्मात, सावलेप, गर्वित, अवलिप्त, उत्सिक्त. 8 गहन; 'h. water' प्रवृद्धा वेला; 'it is h. noon' (नभसः) मध्यमलंकरोति भानुः; 'h. and low' उच्चावच, अधरोत्तर, उत्तमाधम, उन्नतानत, नतोन्नत, निम्नोन्नत; 'h.-er and h.-er' अधिकाधिकं, उत्तरोत्तरं; 'h. price' महामूल्य; 'h.ground' उन्नतभूः; 'as h. as' मात्र (त्री *f.*), द्वयस (सी *f.*), दघ्न (घ्नी *f.*) in comp.; 'he has a h. opinion of you' स त्वां बहु मन्यते. —*adv.* उच्चैः, उच्चं, अति-सु pr.; ऊर्ध्वं, उपरि, उत्तमं, परमं; 'on h.' ऊर्ध्वं, उपरि; 'from on h.' उपरिष्टात्; 'the sea runs h.' बलवत्क्षुब्धः सागरः. 'H.-birth कुलीनता, कुलोत्कर्षः, आभिजात्यं; 'h.-blest' अतिपुण्यवत्, महाभाग, अतिधन्य, परमसुखभाज्; 'h.-blown' अत्युच्छून, अतिस्फीत; 'h.-born' कुलीन, महाकुल-जात-प्रसूत, अभिजात, सुजात, अभिजनवत्, सद्वंश्य, श्रेष्ठ-उत्तम-कुलोद्भव; 'h.-bred' कुलीन, शिष्टाचार, सुजन, सुशील, सद्भावविशिष्ट, सौजन्योपेत, सदाचार, साधुवृत्त; 'h.-built' सोच्छ्राय, उच्च; 'h.-*day*' उत्सवदिनं, उत्सवदिवसः; 'h.-fed' अतिपुष्ट, दृढपुष्ट; 'h.-flying' अपरिमित; 'h.-hand' औद्धत्यं, गर्वः, उद्दामत्वं, निर्यंत्रणत्वं; 'h.-handed' उद्धत, सगर्व, उद्दाम, अनियंत्रण, उच्छृंखल, स्वैरिन्; 'h.-hung' ऊर्ध्वबद्ध; 'h.-land' अधित्यका, उन्नतभूमि *f.*; (*a.*) पर्वतीय, उन्नत; 'h.-lander' पर्वतीयः, पर्वतवासिन् *m.*; 'h.-mettled' महासत्त्व, उरुसत्त्व, ओजस्विन्, अदीनचित्त, तेजस्विन्; गर्वित, अतिमहान्वित; 'h.-minded' महात्मन्, महामनस्क, उदार-धी-चेतस्-चरित, महेच्छ, महाशय; 'h.-principled' साधुचरित्र, पुण्यात्मन्, पुण्यशील; 'h.-priest' पुरोहिताध्यक्षः; 'h.-prized' महामूल्य, महार्घ, बहुमत; 'h.-red' घनारुण, अतिरक्त; 'h.-road,-street,-way' राजमार्गः-पथः, महापथः-मार्गः, घंटापथः, संसरणं, रथ्या, विशिखा, प्रतोली; 'h.-seasoned' सुवासित; 'h.-spirited' महा-उरु-सत्त्व, अकुंठितवृत्ति, ओजस्विन्, ऊर्जित, महेच्छ; 'a h.-spirited speech, ऊर्जितार्थं वचनं (Ki. II. 1); 'h. -treason राजद्रोहः, राजापकारित्वं; 'h.-wrought' यत्न-संस्कृत, प्रयत्नपरिष्कृत; 'h.-wayman' परिपंथिन् *m.*, दस्युः, वाटपाटच्चरः, पाटच्चरः, पथिकत्राः. **-est,** *a.* उच्चतम, तुंगतम, उत्तम, परम. **-ly,** *adv.* उच्चैः. 2 भृशं, अत्यंतं, नितांतं, परमं, परं, अतीव, अति-सु pr.; *See* **Exceedingly,** 'h. pleased' परमानंद-भाज्, हर्षकाष्ठां गत. **-ness,** *s.* देवः (वी *f.*), अत्र-तत्र-भवत् (ती *f.*). **—Height,** *s.* उच्छ्रायः, उच्छ्रयः, उत्सेधः, आरोहः, उन्नयः, तुंगता, उच्चता; उत्कर्षः, उन्नति *f.* 2 उच्चस्थानं, उत्सेधः, उन्नतभूभागः, गिरिः, पर्वतः. 3 शिखरं, अग्रं, शृंगं, शिखा, चूडा. 4 (परा) काष्ठा, कोटिः; अतिभूमिः; परमावधिः, उत्तमावधिः; 'being in the h. of joy' आनंदकोटिमधिगत. 5 कुलोत्कर्षः, परमपदं, श्रेष्ठत्वं, विशिष्टता; 'the h. of winter' शिशिरमध्यं, कठोरीभूतः शिशिरः. **—en,** *v. t.* उन्नी 1 P, उत्कृष् 1 P. 2 वृध् c., उपचि 5 U, एध् c., स्फाय् c. (स्फावयति). *See* **Add to.**

Hilarity, *s.* आनंदः, उल्लासः, उत्साहः, प्रहर्षः, आह्लादः, उत्सवः; *See* **Delight.** **Hilarious,** *a.* हर्षित, आनंद.

Hill, *s.* गिरिः, पर्वतः, अद्रिः, शैलपादः; 'h. near a mountain' पादः, प्रत्यंतपर्वतः. **-ock,** *s.* वप्रः, उन्नतभूभागः; वामलूरः, वल्मीकः-कं, वाकुः, कृमिकाचयः. **-y,** *a.* पर्वतमय (यी *f.*), सपर्वत, पर्वतीय, उन्नतानत, विषम.

Hilt, *s.* त्सरुः, मुष्टि *m. f.*, खड्गमुष्टिः.

Hind, *s.* मृगी, हरिणी, कुरंगी, एणी, पृषती. **2** ग्राम्यजनः, ग्रामिकः, वृषलः

Hind, Hinder, *a.* पश्चिम, जघन्य, पश्चात् in comp., चरम, अपर, अवर; 'h. part' पश्चाद्भागः, पृष्ठदेशः- भागः, पृष्ठं, नितंबः, पश्चिमभागः.

Hinder, *v. t.* नि-विनि-वार् 10 or वृ c., नि-प्रति-षिध् 1 P, रुध् 7 U, नि उप-अव-सं-प्रति°, स्तंभ् 9 P, बाध् 1 A. वि-प्रति-हन् 2 P, प्रतिबंध् 9 P. **-ance,** *s.* प्रतिषेधः, निवारणं, प्रतिबंधः, विघ्नः, अंतरायः, प्रत्यूहः, प्रतिरोधः, व्याघातः, बाधा, विष्टंभः. **-er,** *s.* निवारकः, प्रतिबंधकः, विघ्नकृत् *m.*

Hinge, *s.* कीलं, द्वारसंधिः-ग्रंथिः. **-v.** *i.* (upon) अवलंब् 1 A, अपेक्ष् 1 A; *See* **Depend.**

Hint, *s.* इंगितं, आकूतं, सूचना, संज्ञा, भावः, संकेतः, आशयः. **2** उपन्यासः, उपक्षेपः. **-v.** *t.* इंगितेन सूच् 10, उपन्यस् 4 U, सूच्, उपक्षिप् 6 P, उद्दिश् 6 P, साकूतं निर्दिश् or उपन्यस्.

Hip, *s.* कटि-टी *f.*, नितंबः, श्रोणि-णी *f.*, ककुद्मः, प्रोथः, जघनं, श्रोणिफलकं. **-ped,** *a.* विषण्ण, खिन्न.

Hippopotamus, *s.* करियादस् *n.*

Hire, *v. t.* वेतनेन-मूल्यदानेन नि-प्र-युज् 7 A, 10 or व्या-पृ c. or उप-भुज् 7 P or सेव् 1 A or ग्रह् 9 U, परिक्री 9 A, भट् 1 P or c., भृतिं दा 3 U; 'h. labourers' कर्मकरान् उपनी 1A, or कर्मणि व्यापृ c.; 'a h. ed labourer' भृतिभुज् *m.*, भरण्यभुज् *m.*, भृतकः; 'a person h. ed' कृत-कल्पित-वेतनः. **-s.** वेतनेन ग्रहणं or व्यापारणं, वेतनदानं. **2** भृति *f.*, भृत्या, भरण्यं, वेतनं, भाटकं, मूल्यं, कर्मण्या, विधा, भर्मन् *n.*, निर्वेशः, पणः, निष्क्रयः; 'for h.' पण्य, वेतनेन ग्राह्य, साधारण; 'a woman for h.' पण्यांगना, पण्यस्त्री; 'a teacher for h.' भृतकाध्यापकः. **-ling,** *s.* 'worker for h.' भृतकः, भृतिभुज् *m.*, भरण्यभुज् *m.*, वैतनिकः; कर्मकारः, भृत्यः.

Hirple, *v. i. See* **Limp. -s.** खंजवत्-लंग-गति *f.*

Hirsute, *a.* लोमश, प्रचुरलोमन्.

Hiss, *v. i.* फूत्कारं कृ 8 U or उद्-गॄ 6 P, सीत्कारं कृ, सर्पवत् श्वस् 2 P; 'h. off' सीत्कारेण असंतोषं सूच् 10 or दूरय् c. **-s., -ing,** *s.* फूत्कारः, सीत्कारः, सर्प-श्वासः-नादः.

Hist, *adv.* तूष्णीं भव, वाचंयम *a.* भव.

History, *s.* इतिहासः, पुरावृत्तं, पुराख्यानं, पुराणोपाख्यानं, उपाख्यानं, चरित्रवर्णनं. **2** वृत्तांतः, उदंतः, समाचारः, वार्ता. **-ic, -ical,** *a.* ऐतिहासिक (की *f.*), पुरावृत्त-विषयक, पौराणिक (की *f.*). **-ically,** *adv.* इतिहासानुसारेण. **-Historian, -Historiographer,** *s.* इतिहास-पुरावृत्त-लेखकः-रचकः, पुराणरचकः, चरित्रलेखकः, ऐतिहासिकः.

Histrionic,-al, *a.* नाटकीय, रंग-नाट्य-योग्य, रंगानुरूप.

Hit, *v. t.* प्र-हृ 1 P, तड् 10; अभि-नि-आ-हन् 2 P, तुद् 6 P, व्यध् 4 P. **2** (Upon) (दैवात्) आ-सद् c., आप् 5 P, अधिगम् 1 P, लभ् 1 A; 'arrows h. a moving mark' इषवः सिध्यंति लक्ष्ये चले (S. 2). **-v. i.** संघट्ट् 1 A, समा-प्रति-हन्, अभिसं-पत् 1 P. **-s.** प्रहारः, आघातः, ताडनं, घातः. **2** दैव-घटना, संगति *f.*, दैवं.

Hitch, *v. t.* ग्रह् 9 U, धृ 1 U, 10, आकृष् 1 P. **-v. i.** ग्रह्-धृ-pass. **2 Hop,** q. v. **-s.** अंतरायः, प्रत्यूहः; *See* **Obstacle.**

Hithe, *s.* घट्टः, तरस्थानं.

Hither, *adv.* अत्र, इह, इतः. **-most,** *a.* आसन्नतम, नेदिष्ठ, अत्यंतिक. **-ward,** *adv.* इतः, अत्र. **-Hitherto,** *adv.* अद्ययावत्, आवर्तमानकालात्, अद्यावधि, एतत्कालपर्यंतं.

Hive, *s.* मधुकोषः, करंडः, छत्रकः, चषालः. **-v.** *t.* मधुकोषे निधा 3 U or निविश् c.

Hoar, *a.* धवल, शुभ्र, सित, श्वेत, शुक्ल; *See* **White;** 'h.-frost' तुषारः, अवश्यायः; *See* **Frost.**

Hoard, *s.* संचयः, निचयः, निवहः, पुंजः, राशिः, गणः, संघः, संग्रहः, निधिः; *See* **Multitude. -v.** *t.* संचि 5 U, संग्रह् 9 U, समा-हृ 1 P, राशीकृ 8 U, पुंजीकृ.

Hoarse, *a.* रूक्ष, परुष, कर्कश; भग्न, सगद्गद. **-ly,** *adv.* रूक्षस्वरेण, स्वरभंगेन, सगद्गदं **-ness,** *s.* भंगः, भेदः, रूक्षता; स्वरभंगः-रूक्षता.

Hoary, *a.* सित, धवल, श्वेत, शुक्ल, गौर (री *f.*), शुभ्र. **2** पलित, पक्व-पलित-केश.

Hoax, *s.* वंचनं-ना, प्रतारणं-णा, छलं, कपटं, विप्रलंभः. **-v.** *t.* वंच् 10, प्र-तॄ c., विप्र-लभ् 1 A.

Hob, *s.* वृषलः, ग्राम्यः, जानपदः.

Hobble, *v. i. See* **Limp.**

Hobbledehoy, *s.* युवन् *m.*

Hobby, *s.* प्रियवस्तु-द्रव्यं, चिरकाम्यं, निर्बंधः, अभीष्टमनोरथः, लहरी, छंदः, अभिरुचि *f.*; 'h.-horse' क्रीडाश्वः, क्रीडाद्रव्यं, क्रीडनकं.

Hobgoblin, *s.* भूतः, पिशाचः. वेतालः, राक्षसः; *See* **Demon, Devil.**

Hocus, *v. t. See* **Hoax. -pocus,** *s.* मंत्रतंत्रं, कुहकः, इंद्रजालं.

Hod, *s.* लेपाधारः, सुधाभाजनं.

Hodge-podge, *s.* संकरः, सन्निपातः, नानाद्रव्यसमूहः, प्रकीर्णकं.

Hoe, *s.* खनित्रं, अवदारणः, स्तंबघ्नः. —*v. t.* खनित्रेण खन् 1 P, भूमिं भिद् 7 P, अवदृ 10.

Hog, *s.* वराहः, किरिः, शू(सू)करः; *See* **Boar;** 'village h.' विड्वरः, ग्राम्यः; 'h.-herd' शूकरपालः-पोषकः; 'h.-sty' शूकरस्थानं-वासः. **-gish,** *a.* शूकरोपम, शूकरीय, वाराह (ही *f.*), शूकरगुणविशिष्ट.

Hogo, *s.* अति-तीक्ष्ण-स्वादः.

Hog-weed, *s.* शोथघ्नी, पुनर्नवा, शोथजित् *f.*

Hoiden, *s.* प्रगल्भा, निर्लज्जा.

Hoist, *v. t.* उन्नम् c. (नमयति), उद्गम् c., उच्छ्रि c., उद्यम् 1 A, उन्नी 1 P, उद्-धृ-हृ 1 P, उत्तुल् 10, उत्था c. (उत्थापयति.)

Hold, *v. t.* धृ 1 P, 10, अव-लंब् 1 A, आ-दा 3 A, ग्रह् 9 U, परामृश् 6 P, हस्तेन धृ or अवलंब्. **2** स्तंभ् 9 P, नि-अव-रुध् 7 U, बलाद् धृ. **3** (possess) भृ 3 U, आ-धा 3 U; *See* **Have. 4** (Contain) धृ, परिग्रह्, आ-धा, समाविश् c., भृ, आ-दा. **5** पा c. (पालयति), रक्ष् 1 P, न त्यज् 1 P. **6** (As a festival) अनुष्ठा 1 P, सेव् 1 A, पा c. (पालयति), कृ 8 U, सं-पद् c., निर्वह् c., वि-धा, यथाविधि कृ, अभिनंद् c. **7** मन् 4 A, गण् 10; *See* **Consider.** 'I h. them of no account' का-कियती-मात्रा तेषां मत्पुरतः, तानहं तृणाय मन्ये or तृणीकरोमि; 'h. an opinion' मतं अवलंब् or आश्रि 1 U, मन्; 'h. one's tongue' जिह्वां धृ or रक्ष्, 'h. your tongue' वाचंयमो भव, वाचं नियच्छ, तूष्णीं-जोषं-आस्स्व; 'h. a meeting' सभां मिल् c. or सभा-ह्वे 1 P; 'a meeting was held' परिषद् मिलिता; 'h. in esteem' बहु मन्; 'h. in contempt' अवगण्, अवमन्, तृणीकृ, तृणाय मन्; 'h. a council' सभां निमंत्र् 10 A or आह्वे; 'h. a consultation संमंत्र्, मंत्रणां कृ; 'I h. you responsible' for this act' अस्य त्वयोत्तरं दातव्यं. —*v. i.* स्था 1 P, स्थिरीभू, सं-स्था 1 A; चिरस्थायीभू, स्थायीभू. **2** अनुबंध् 9 P or pass.; सं-संज् pass., संलग्नीभू, आलंब् 1 A. **3** विरम् 1 P, निवृत् 1 A (with abl.); आत्मानं संयम् 1 A or निग्रह्, परिहृ 1 P, त्यज्; 'hold hold!' विरम विरम, मा मा एवं, मा तावत्. **4** अधीन *a.* भू, आश्रि, अव-आ-लंब्. **5** (As a rule) गम्, न व्यभिचर् 1 P; 'this rule h.s everywhere' सर्वगामी-अव्यभिचारी-अयं नियमः. —*s.* धरणं, धृति *f.*, ग्रहः-हणं, अवलंबः-बनं, हस्तेन ग्रहणं-धरणं; 'letting go the h.' मुक्त-ग्रस्त-हस्त, मुक्तग्रह. **2** कारा, कारागृहं, कारागारं, बंधनस्थानं, गुप्ति *f.* **3** आधारः, आ-अव-लंबः-बनं, उपस्तंभः, आश्रयः. **4** दुर्गं, कोटः. **5** मुष्टि *m. f.*, वारंगः. **6** आस्पदं, पदं, अधिकारः, वशः-शं; 'red colour takes a firm h. on a white cloth' रागः शुक्लपटे स्थायीभवति (P. I. 1); 'had a h. on the mind of the people' स लोकस्य मन आवृद्धे (R. IV. 8); 'the advice took no h. on (her) mind' लेभेऽन्तरं चेतसि नोपदेशः (R. VI. 66). **-back,** नि-वृ c., वार् 10, संह् 1 P, निग्रह्, विकल्प् 1 A, विचर् c.; *See* **Hesitate. -forth,** दृश् c., पुरो निधा. **-in,** निग्रह्, प्रति-संह्, नि-सं-यम्. **-off,** विलंब् 1 A, विकल्प्. **-on,** प्रवृत् c., न विरम्, न मुच् 6 P, न त्यज्, उद्वह् 1 P, निर्वह् c. **-out,** प्रसृ c., वितन् 8 U, दीर्घीकृ. **2** दृश् c., उपन्यस् 4 U, उपक्षिप् 6 P, उप-स्था c. (स्थापयति); (*v. i.*) चिरं यावत्सह् 1 A or युध् 4 A or प्रतिकृ. **-together,** संबंध् pass., संश्लिष् 4 P, संलग् 1 P **-up,** उन्नम् c. (नमयति), उद्यम्, उच्छ्रि 1 U or c., ऊर्ध्वीकृ. **2** उत्तंभ्, अवष्टंभ्, आ-अव-लंब्, भृ, धृ. **-er,** *s.* धारकः, धारयितृ *m.*, ग्राहकः, धरः-आधारः- in comp. **-ing,** *s.* धरणं, ग्रहणं, &c. —*a.* धारिन्, धर in comp.; oft. by हस्त in comp.; 'h. a sword' कृपाणपाणिः. **-Holdfast,** *s.* ग्राहकः, ग्रहणी, बंधनी, कुड्डुपः. **2** दृढ-बद्ध-मुष्टिः, अमुक्तहस्तः.

Hole, *s.* विवरं, बिलं, छिद्रं, रंध्रं, शुषि(षि)रं, कुहरं, निर्व्यथनं, रोकं, वपा, सुषि *f.*; श्वभ्रं, गर्तः-र्ता, अवटः (in the ground). **2** कंदरः-रं-रा, गुहा, गह्वरं, दरी, खातं (of mountains). **3** (Of garments &c. or fig.) रंध्रं, छिद्रं; 'a rat digs a h. and a snake uses it' एकः परिश्रमं करोति, अन्यस्तत्फलमुपभुंक्ते; 'picking h.s (in the character &c.) of others' छिद्रान्वेषिन्, दोषैकदृश्, पुरोभागिन्, रंध्रानुसारिन्; 'full of h.s' अनेकरंध्र, बहुविवर.

Hollow, *a.* रिक्त-शून्य-गर्भ, अंतःशून्य, शून्यमध्य-उदर; उदराकृति, सुषिर, गुहाकार. **2** असार, निःसत्त्व, निःसार, फल्गु, शून्य. **3** मोघ, निरर्थक, निष्फल. **4** असत्य, वितथ, मिथ्या, in comp. **5** ग(गं)भीर, मंद्र, मंद्र. —*s.* (Of trees) कोटरः-रं, कोलः, निष्कुहः. **2** विवरं, गुहा, बिलं, कुहरं, अवटः; *See* **Hole. 3** गर्भः, उदरं, अभ्यंतरं, कोशं. **4** खातं, खातभूः, गर्तः-र्ता. **5** दरी, कंदरः, अग्निद्रोणी, कंदरभूः. **6** कुल्या, प्रणाली; 'h. of the hand' पुटः, करपुटः-कोषः

' h. of the navel ' नाभिगर्तो, नाभ्यावर्तः; ' ground full of h. s ' उत्खातिनी भूमिः (S. 1); ' natural h. ' देवखातं; ' h. of the ear ' ऋषभः, ' h. s in the buttocks ' जघनकूपकौ, गर्तौ. **-***v. t.* उत्खन् 1 P, पुटीकृ 8 U. **-ness,** *s.* शून्यता, असारता, असत्यता, &c.

Holocaust, *s.* होमः.

Holy, *a.* पुण्य, पवित्र, परिपूत, साधु, शुचि, विमल; पुण्यात्मन्, शुचिव्रत, धार्मिक (की *f.*), धर्म-पुण्य-शील, धर्मात्मन्, शुद्धमति; ' h. study ' वेदाध्ययनं; ' h. wisdom ' ब्रह्मज्ञानं; ' h. writing ' श्रुतिः, वेदाः, निगमः; ' h. land ' पुण्यभूमिः; ' h. place of pilgrimage ' तीर्थं, क्षेत्रं, पुण्यस्थानं-तीर्थं. **-ly,** *adv.* पुण्यं, पवित्रतया, शुचिवत्. **-ness,** *s.* पवित्रता, पुण्यता, शुचिता, वैमल्यं, पुण्यशीलता, धार्मिकत्वं; ' his or her h. ' भगवान्, भगवती. **-Holiday,** *s.* पुण्याहं, पुण्यदिनं. **2** अनध्यायः, अनध्याय-दिवसः-महोत्सवः. **3** उत्सवः, पर्वन् *n.*, उद्धर्षः, उत्सव-उद्धर्ष-दिनं; ' h. people ' यात्राजनः.

Homage, *s.* नमस्कारः, अभिवंदनं, प्रणामः, प्रणति *f.*, पूजा, अर्चनं, उपासना, प्रणिपातः, सेवांजलिः; सेवा, आदरः, प्रभुभक्ति *f.*; ' pay or do h. ' प्रणम् 1 P, वंद् 1 A, प्रणिपत् 1 P; *See* **Bow.**

Home, *s.* गृहं, वासः, वासस्थानं-भूमि *f.*,स्वगृहं, स्व or निज-गेहं-देशः-वासः-स्थानं-भवनं ; *See* **House;** 'devoted to h.' गृहासक्तचित्त. **-***adv.* गृहं, गृहं प्रति; 'the words went h. to his heart' तद्वचः तस्य हृदयमर्मास्पृशत्; 'touching h.' मर्मस्पृश्-भिद्; ' goes h. to me ' मामेव लक्षीकरोति (S. 7); ' h. -born ' गृहजात; ' h.-bound ' गृहगामिन्; ' h.-bred ' गृहज-जात, गृह्य; ' h.-made ' गृहनिर्मित, गृहोत्पन्न; 'h.-sick ' गृहविरहार्त; ' h.-stall, ' -stead ' गृहं, वासः; वेश्मभूः, वास्तु *m. n.* **-less,** *a.* निरालय, निराश्रय, निर्गृह. **-ly,** *a.* गृह्य, गृहज. **2** ग्राम्य,ग्रामीण-य, अशिष्ट, प्राकृत, असभ्य, अश्लील, असंस्कृत. **-***adv.* ग्राम्यवत्, असभ्यतया, अशिष्टप्रकारेण. **-ward,** *adv.* गृहाभिमुखं, अभिगृहं.

Homicide, *s.* नृहत्या, मनुष्यवधः. **2** (Person) मनुष्यघातिन् *m.*, नृहंतृ *m.*, मनुष्यघातकः. **-al,** *a* नृघातिन्.

Homily, *s.* धर्मवाक्यं.

Homogeneal, Homogeneous, *a.* समान-जाति-जातीय,स-एक-जाति, सवर्ण, एक-स-धर्मन, समान-भाव, एक-स-जातीय; ' h. vowels ' सवर्णाः.

Homologous, *a.* तुल्य-सम-परिमाण.

Homonym, भिन्नार्थः शब्दः; ' a collection of h. s ' भिन्नार्थवर्गः. **-ous,** *a.* भिन्नार्थ, अनेकार्थ

Hone, *s.* शाणः, शाणाश्मन् *m.*

Honest, *a.* शुचि,ऋजु,सरल,अमायिन्,दक्षिण, अकुटिल, अजिह्म, शुद्धमति-भाव, शुद्धात्मन्, अकपट, निष्कपट, निर्व्याज, निर्व्यलीक, अव्याज, विमलात्मन्, दंभहीन, न्याय्य,न्याय्याचार, सच्चरित, न्यायवर्तिन्, साधुवृत्त-शील, साधु, प्रांजल, सत्यवृत्त, सत्यशील, सत्यवादिन्. **2** अवितथ, सत्य, अकृत्रिम,अकृतक; *See* **Frank** also; ' h. gains ' न्यायार्जित; ' h. statement' निर्व्याजं वचनं. **-ly,** *adv.* सरलं, न्यायेन, न्यायतः, शुचितया, निष्कपटं, निर्व्याजं, अमायया, निर्व्यलीकं. **-y,** *s.* शुचिता, आर्जवं, निष्कापट्यं, सारल्यं, अकौटिल्यं, दाक्षिण्यं, अमाया, अकपट, अव्याजः, शुद्धभावः, वैमल्यं, निर्व्यलीकता, अजिह्मता, सत्यता, अकृतकता; ' h. is the best policy ' भावशुद्धिः एव साधिष्ठा आचारसरणिः, सारल्यं सत्तमो मार्गः.

Honey, *s.* मधु *n.*, क्षौद्रं, माक्षिकं, सारघं; ' h. of flowers ' पुष्पासवं, पुष्परसः-सारः, कुसुममधु; 'h.-bee' मधुमक्षिका, सरघा; ' h.-comb ' मधुकोशः, करंडः; ' h.-moon ' आनंदमासः; ' h.-tongued ' मधुरभाषिन्, मधुरवाच्. **-***v. t.* मधुरीकृ 8 U. **-***v. i.* उपलल् 10; *See* **Fawn. -ed,** *a.* मधुमधुर, सुधास्यंदिन्, मधुर.

Honor, *v. t.* पूज् 10 अर्च् 1 P, 10, मन् c., संभू c., सत्कृ 8 U, पुरस्कृ, मह् 1 P, 10, आदृ 6 A. **2** सेव् 1 A, श्रु desid. (शुश्रूषते), आराध् c ; ' h. ed the invitation ' निमंत्रणमाद्रियत, सगौरवं स्वीचकार. **3** अनुग्रह् 9 P, प्रसद् 1 P (with loc). **-***s.* मानः, संमानः,पूजा,अर्चनं, अर्हणा, संभावना, आदरः, सत्कारः. **2** सेवा, शुश्रूषा, आराधनं. **3** ख्याति *f.*, कीर्ति *f.*, यशस् *n.*, प्रतिष्ठा, गौरवं, प्रतिपत्ति *f.*, उत्कर्षः, उत्कृष्ट-प्रधान-पदं, उन्नति *f.*; कुलीनता, आभिजात्यं, प्राधान्यं, श्रेष्ठत्वं; ' your or his h. ' अत्र-तत्र-भवान्, भवत्. **-able,** *a.* पूज्य, मान्य, माननीय, पूजार्ह, आदरणीय. **2** सु-प्र-वि-ख्यात, विश्रुत, सुप्रसिद्ध, प्रतिपत्तिमत्,महायशस्. **3** यशस्कर-कीर्तिकर (री *f.*), प्रतिष्ठावह, श्लाघ्य, प्रशस्य, मानद, गौरवान्वित. **4** कुलीन, अभिजात, महाकुल, उदारचित्त-चरित; *See* **Noble. 5** शुचि, न्याय्याचार, सच्चरित, साधुवृत्त, पुण्यात्मन्, शुचिव्रत; *See* **Honest. -ary,** *a.* मानद, कीर्तिकर, यशस्कर, प्रशस्य. **2** अलाभकर, मानमात्रदायिन्. **-Honorably,** *adv.* समानं, सगौरवं, श्लाघ्यप्रकारेण, प्रशंसापूर्वं, सुयशसा, प्रतिष्ठापूर्वं. **2** शुचिवत्, धार्मिकतया, ऋजुतया, सरलतया, न्यायतः.

Honorarium, *s.* दक्षिणा.

Hood, *s.* फणा-णः, फटा, स्फोटा; ' expands the h. ' फणां कुरुते (S. 6); ' expanded

h. ' भोगः. 2 फणाकृति शिरस्कं. -v. t. शिरआपेन पिधा 3 U or प्रावृ 5 U.

Hoodwink, *v. t.* (नयने) वस्त्रेण पिधा 3 U or आच्छद् 10 or आवृ 5 U.

Hoof, *s.* खुरः, शफः-फं, क्षुरः, शिफः, निघृष्वः. **-ed,** *a.* खुरिन्, खुरयुक्त, शफयुक्त.

Hook, *s.* आकर्षणी, ग्रहणी, धरणी; ' fish-h. ' बडिशं-शा-शी, मत्स्यवेधनी; ' h. for elephants ' अंकुशः, सृ(सृ)णि *f.* -v. *t.* बडिशेन धृ 1 P or ग्रह् 9 U. **-ed,** *a.* वक्र, कुटिल, कुंचित, अंकुशाकार, जिह्म; *See* **Crooked.**

Hoop, *s.* चक्रं, वलयः-यं. 2 क्रीडाचक्रं. -v. *t.* लोहवलयैः युज् 10. 2 उच्चैः घुष् 10.

Hoot, *s.* घु(घू)त्कारः. 2 धिक्कारः, उच्चैः अप्रशंसा-सूचनं, दीर्घघोषः. -v. *i.* घूत्काररवं कृ 8 U, उच्चैः आरट् 1 P or घुष् 10, दीर्घं रु 2 P; ' h. at ' उच्चैः अवज्ञां-धिक्कारं-सूच् 10.

Hop, *v. i.* प्लु 1 A, वल्ग् 1 U, एकपादेन नृत् 4 P. -*s.* प्लुतं, वाल्गितं, प्लवः, एकपादेन नृत्यं.

Hope, *v. t.* आशंस् 1 A, उत्-प्रति-अप-ईक्ष् 1 A, स्पृह् 10, प्रत्याकांक्ष् 1 P, वांछ् 1 P, आशां धृ or बंह् 1 P; in implied questions, gen. ex. by अपि, कच्चित् or अपि नाम; ' I h. this lotus-leaf breeze pleases you ' अपि सुखयति ते नलिनीपत्रवातः (S. 3); अपि नाम रामभद्रः पुनरपीदं वनमलंकुर्यात् (U. 2), कच्चिन्मृगीणामनघा प्रसूतिः (R. v. 7); ' I h. not ' न खलु; न खलु तामभिक्रुद्धो गुरुः (V. 3) ' I h. the preceptor did not get angry with her'; ' I scarcely h. ed to see you here ' न खलु मे आसीदाशंसा यदत्र भवंतं प्रेक्षिष्ये. -*s.* आशा प्रत्याशा, आशंसा, आकांक्षा, अपेक्षा, प्रतीक्षा, उद्वीक्षणं; स्पृहा, मनोरथः, वांछा, इच्छा, आशाबंधः. 2 (Giving h.) आश्वासनं, आश्वासः ; ' having h. s fulfilled ' पूर्णाश; ' a vain h. ' वृथाभिलाषः, मोघाशा, ' h.-ing against h. ' अतीव दूरापेतं. **-ful,** *a.* आशान्वित, आशावत्, आशायुक्त, आशाबद्ध, स्पृहयालु, अपेक्षिन् समत्याश, आशाविष्ट. 2 (Giving hopes) आशाजनन (नी *f.*), आशाकारिन्. **-fully,** *adv.* साशंसं, समत्याशं. **-less,** *a.* निराश, आशातीत, आशाहीन, हताश, त्यक्ताश, निरपेक्ष. **-lessly,** *adv.* नैराश्यात्, सनैराश्य.

Hora, *s.* मुहूर्तः, घटिका. **-al,-ary,** *a.* मौहूर्तिक (की *f.*).

Horde, *s.* महान् गणः, बृहत्संघः, महौघः, स्तोमः; *See* **Multitude.**

Horizon, *s.* क्षितिजं, दिङ्मंडलं, दिक्चक्रं, अंबरांतः; चक्रं, मंडलं; ' the eastern h. ' प्राची-ऐंद्री-दिक्, प्राचीमूलं. **-Horizontal,** *a.* सम, दिगंतसम, अनुप्रस्थ; ' h. plane ' समभूभागः, समा भूमिः. **-ly,** *adv.* समं, अनुप्रस्थं.

Horn, *s.* शृंगं, विषाणः-णं, कूणिका; ' h. of a buffalo ' गवलं. 2 काहलः-ला, शंखः. 3 चंद्राग्रं, चंद्रशिखा. **-ed,** *a.* शृंगिन्, विषाणिन्, शृंगयुक्त-विशिष्ट. 2 शृंगाकार, शृंगाकृति. **-y,** *a.* शार्ंग (र्गी *f.*). 2 कठिन; *See* **hard.**

Hornet, *s.* वरटा, बृहद्बोलः.

Horologue, *s.* घटी, कालमापनयंत्रं.

Horoscope, *s.* जन्मपत्रिका, जन्मपत्रं, जन्मयोगपत्रं.

Horror, *s.* त्रासः, संत्रासः, साध्वसं, भयकंपः, भयसंहर्षः. 2 बीभत्सता, रौद्रता, घोरता, भैरवं, भयानकं, भीष्मं, भीषणं. **-Horrific,** *a.* भीषण, उग्र, भयानक, भयावह. **-Horrid, Horrible,** *a.* घोर, दारुण, भीम, भयानक उग्र, भीषण, कराल, विकट; *See* **Fearful -ly,** *adv.* घोरं, दारुणं, रौद्रं, उग्रतया; बीभत्सतया. **-Horrify,** *v. t.* **Frighten,** q. v. **-ed,** *a.* साध्वसोपहत, भीत, संत्रस्त, भयसंहृष्ट.

Horripilate, *v. t.* पुलकयति-कंटकयति-रोमांचयति (D), रोमाणि उद्गम् c. or उद्धृष् c. **-ed,** *a.* पुलकित, कंटकित, सपुलक, रोमांचित. **-ion,** *s.* पुलकः, रोमांचः, रोमहर्षः-र्षणं, रोमोद्गमः-द्गतत्वं, पुलकोद्भेदः, उद्धर्षणं.

Horse, *s.* अश्वः, तुरगः, तुरंगः-गमः, हयः, सप्तिः, वाजिन् *m.*, वाहः, अर्वन् *m.*, घोटकः, वीतिः; गंधर्वः, सैंधवः; ' a well-bred h. ' आजानेयः, कुलीनः, भूमिरक्षकः, सिंधुवारः; ' a well-trained h.' साधुवाहिन् *m.*, विनीतः; ' a white h. ' कर्कः; ' a bay h. ' उकनाहः, कियाहः; 'a fleet h.' जवनः, जवाधिकः; 'a pack h.' पृष्ठ्यः, स्थौरिन् *m.*, स्थोरिन् *m.*; 'a h. for a sacrifice' ययुः, अश्वमेधीयः; ' a chariot-h. ' रथ्यः; ' h.'s pace ' गतिः, धारा; (namely) आस्कंदितं ' full gallop '; धो(धौ)रितकं, धोरितं ' trot or ambling '; रेचितं ' cantering '; वल्गितं ' vaulting'; प्लुतं 'bounding or capering'; 'h.'s nose' घोणा, प्रोथः-थं; ' h.s tail' पुच्छः-च्छं, लूमं, लांगूलं; 'h.'s tail hair ' बालधिः, बालहस्तः; ' a number of h. s ' आश्वं, अश्वीयं; ' relating to a h. ' अश्वीय, आश्विक (की *f.*); ' h.-soldiers ' आश्वं, आश्विकं, अश्वारोहगणः; ' h.-back ' अश्वपृष्ठं; ' go on h.-back ' अश्वेन गम् or चर् 1 P; ' going on h.-back ' तुरंगयायिन्, सादिन्; ' h.-bean ' मुद्गः, माषः, शिंबा; ' h.-breaking ' अश्वशिक्षा-दमनं-विनयः; ' h.-breaker ' अश्वविनेतृ *m.*-शिक्षकः; 'h.-

dealer ' अश्वव्यापारिन् *m.*, हयज्ञः; 'h.-driving ' अश्वसारथ्यं, रथवाहनकौशलं; 'h.-laugh ' अट्टहासः, अतिहासः, अतिहसितं, आच्छुरितं; 'h.-man ' अश्वारोहः, तुरंगस्थः, सादिन् *m.*, तुरागिन् *m.*, हयारूढः, अश्वारूढः, 'h.-manship ' अश्वारोहणकौशलं-विद्या, अश्वविद्या, अश्वहृदयं; ' h.-shoe ' अश्वपादत्रं; ' h.-trappings ' आहानं, अश्वपरिष्तोमः, अश्वास्तरणं; ' h.-whip ' कशा, अश्वताडनी, प्रतिष्कषः-शः, चर्मदंडः; (*v. t.*) कशया तड् 10 or प्र-हृ 1 P.

Hortation, *See* **Exhortation.**

Horticulture, *s.* उद्यानविद्या, उद्यानपालनं. **-ist,** *s.* उद्यानविद्याज्ञः.

Hose, *s.* और्णं पादत्राणं **-Hosier,** *s.* और्णपादत्रविक्रयिन् *m.*

Hospitable, *a.* आतिथेय (यी *f.*), सत्कारशील, अतिथिपूजक, आतिथ्यकारिन्. **-Hospitably,** *adv.* सादरं, समभ्रयं, सबहुमानं, आतिथेयसत्कारेण, सत्कार-आतिथ्यपूर्वं; 'to receive h. ' सत्कृ 8 U, पूज् 10, सं-भू c.

Hospital, *s.* आतुरशाला, रुग्णागारं, आरोग्यचिकित्सा-शाला, रुजोपायशाला.

Hospitality, *s.* आतिथ्यं, आतिथ्यकर्मन् *n.*, अतिथिसत्कारः-पूजा-सेवा-क्रिया; सत्कारः, सत्क्रिया, सत्कृति *f.*, उपचारः, पूजा, सेवनं.

Host, *s.* गणः, संघः, समूहः, ओघः, निवहः; *See* **Multitude. 2** चमूः, सेना, अनीकं, वरूथिनी. **3** गृहिन् *m.*, भोजनदायिन् *m.*, निमंत्रणकृत्, निमंत्रकः, आतिथ्यकृत्. **-age,** *s.* विश्वासस्थानं, शरीरबंधकः; 'retaining 4 hares as h. s ' चतुरः शशकान् विश्वासस्थानं धृत्वा (P. I. 8). **-ess,** *s.* गृहिणी, भोजनदात्री, आतिथ्यकारिणी.

Hostel, Hostelry, *s.* पथिकाश्रमः, उत्तरणगृहं-शाला.

Hostile, *a.* विपक्ष, विरुद्ध, वैरिन, प्रत्यर्थिन्, प्रतिकूल, विपरीत, विद्वेषिन्, अहित, प्रतिरोधिन् 'a h. invasion ' शत्रुविग्रहः, शत्रुयानं; ' to be h. ' विरुध् 7 U, द्विष् 2 U, पर्यवस्था 1 A, प्रतिकूलयति-वैरायते (D.), विपक्षीप्रत्यर्थी-भू. **-ly,** *adv.* शत्रुवत्, विपक्षवत्. **-ity,** *s.* विपक्षता, वैरं, शत्रुता, वैरभावः, विरोधः, प्रतिद्वंद्वं, विद्वेषः; 'in a state of constant h. ' सदाबद्धवैर *a.*; ' natural h ' स्वभाव-जाति-वैरं, शाश्वतिकः विरोधः. **2** विग्रहः, युद्धं, संग्रामः, युद्धभावः.

Hostler, *s.* अश्वपालकः.

Hot, *a.* उष्ण, आतपाक्रांत, आतपवत्, तप्त, संउत्-तप्त, सोष्ण; प्रखर, उग्र, तिग्म, चंड, खर, ताम्र, तीक्ष्ण. **2** ग्रीष्म, नैदाघ (घी *f*), घर्म in comp. **3** शीघ्र-सुलभ-कोपिन्, क्रोधिन्, संरंभिन्. **4** साहसिन्, तीक्ष्णकर्मन्, 'h. weather or season ' ग्रीष्मः, निदाघः, घर्म-ग्रीष्म-उष्णकालः; ' to make h. ' तप् c.; ' to be h. ' तप् 1 P, 4 A, उष्णीभू ; ' h.-bed ' उष्णस्थलं, (fig.) क्षेत्रं ; h.-blooded or -headed ' चंडप्रकृति-शील, संरंभिन्, शीघ्रकोपिन्, उन्मत्त, उद्धत, तीक्ष्णकर्मन्, साहसिक, साहसिन्. **-ly,** *adv.* तीक्ष्णं, तीव्रं, उग्रं, उष्णं; सोत्साहं; व्यग्रं, सोत्साहं, सोत्कटं. **-ness,** *s.* उष्णता, तापः, प्रखरता, उग्रता, चंडता, तिग्मता, औष्ण्यं, निदाघः, घर्मता. **2** उत्तापः, तीक्ष्णता, संरंभः, व्यग्रता; ' h. of temper ' शीघ्रकोपित्वं, चंडता.

Hotch-potch, *s.* प्रकीर्णकं, नानाशाकादिसंमिश्रणं.

Hotel, *s.* पथिकाश्रमः, भोजनगृहं.

Hotspur, *s.* संरंभिन् *m.*, साहसिकः.

Hough, *s.* जंघास्थिशिरा.

Hound, *s.* विश्वकद्रुः, मृगदंशकः, आखेटिकः, मृगयाकुक्कुरः.

Hour, *s.* घटी, घटिका, नाडिका; ' h.-drum ' नाडिकाविच्छेदपटहः. **2** (H. s) कालः; 'at all h. s ' सदा, सर्वदा; 'in an evil h.' अशुभे लग्ने-मुहूर्ते; ' an h. and a half. ' अर्धयामः. **-ly,** *a.* प्रतिघटिकं *adv.*

Houri, *s.* दिव्यांगना, स्वर्गकन्या, दिव्ययोषित्.

House, *s.* गृहं, गेहं, अ(आ)गारं, सदनं, वेश्मन्-सद्मन् *n.*, निकेतनं, मंदिरं, वासः, आ-निवासः, भवनं, आयतनं, नि-आ-लयः, ओकस्-धामन् *n.*, वसति *f.*, निवासस्थानं, आवसथः, उदवसितं, निकाय्यः, निशांतं, व(प)स्त्यं; ' body of a h. ' गर्भागारं, वासगृहं. **2** कुलं, अन्वयः, वंशः. **3** गृहजनः, कुटुंबं, परिवारः; ' h.-breaker ' कुड्यच्छेदिन् *m.*, भित्तिसंधि-चौरः, कपाटघ्नः, गृहभेदकः; 'h.-dog ' गृहकुक्कुरः; ' h.-door ' गृहद्वारं, ' h.-hold ' परिवारः, कुटुंब-वर्गः, परिजनः, गृहपरिजनः, परिवारः; (*a.*) गृह्य, ex. by गृह in comp.; 'h.-hold duties' गृहकार्याणि, गृहाचाराः; ' h.-hold gods ' कुलदेवताः; ' h.-holder ' गृहिन् *m.*, गृहस्थः, गृहपतिः, गृहमेधिन् *m.*, कुटुंबिन् *m.*, गेहिन् *m.*; ' h.-hold stuff ' गृहोपस्करः, गृहसामग्री; ' h.-keeper ' गृहारक्षकः (-क्षिका *f.*); ' h.-keeping ' गृहव्यापारः-कार्यं-कर्मन् *n.* 'h.-maid' दासी गृहदासी-मार्जनी; ' h.-room ' वासस्थानं, वेश्मन् *n.*'h.-warming' गृहप्रवेशः;'h.-wife' गृहिणी, गेहिनी, गृहकार्यकुशला-दक्षा, गृहमेधिनी; ' h.-wifery ' गृहकार्यकुशलता-नैपुण्यं, गृहकर्मानुष्ठानं, परिमितव्ययः. **-less,** *a.* गृहहीन-शून्य, निरालय, अशरण, निराश्रय, निर्गृह.

Housing, *s.* परिस्तो(हो)मः, सज्जा, कल्पना, कुथः, आस्तरः, प्रसाधनं.

Hovel, *s.* उटजः-जं, कुटीरः, कुटी, पर्णशाला, तृणकुटी.

Hover, *v. i.* परितः विसृप् 1 P or डी 1 A, आकाशे व्यावृत् 1 A or विसृप् or विचल् 1 P, परिभ्रम् 1, 4 P; 'h. about' मंडले चर् 1 P, (वृषिस्योपरि मंडले चरति Mr. 3); मंडलाकारेण भ्रम्. 2 (fig.) विशंक् 1 A, विकल्प् 1 A, विचर् c. **-ing,** *s.* परिभ्रमणं, मंडलावृत्ति *f.*

How, *adv.* कथं, केन प्रकारेण-रूपेण. 2 कियत् (in 'how long,' 'how far'); 'h. much' कियत्; 'h. many' कति (pl.); 'h. long' कियच्चिरं, कियंतं कालं; 'h. many kinds' कतिविधाः; 'h. many times' कतिकृत्वः; 'h. now' ननु, ननु भोः; 'h. far' कियद्दूरं, कियदवधि; 'h. much more-less' किमुत, किं पुनः, किमु; 'h. else' अथ किं; with *adj.* ex. by अहो; 'h. pleasing' अहो मधुरं; अहो पापं, &c.

Howdah, *s.* वरंडकः.

However, Howsoever, *adv.* यथातथा, येनकेन प्रकारेण; (with *adj.*) by अपि, or by नाम with imp. of verb; 'h. industrious a man may be' दीर्घव्यवसायोपि नरः, करोतु नाम व्यवसायं नरः (H. 2). **-conj.** (Howbeit) किंतु, अपि तु, तु, परंतु, तथापि, पुनः.

Howl, *v. i.* आक्रंद् 1 P, उत्क्रुश् 1 P, उच्चैः रस्-रुद् 1 P, गर्ज् 1 P, दीर्घं विरु 2 P, रै 1 P. **-s., -ing,** *s.* उत्क्रोशः- शनं, आक्रंदनं, दीर्घरुतं, आरटनं, र(रा)वः, दीर्घरवः, गर्जनं, रसितं; 'h. of dogs' भषणं, बुक्कनं, रायणं.

Hub, *s.* नाभि *f.* 2 स्तरुः. 3 लक्ष्यं, शरव्यं.

Hubbub, *s.* कोलाहलः, कलकलः; तुमुलं, तुमुलरवः- नादः, संकीर्णनादः.

Hucklebone, *s.* श्रोण्यस्थि *n.*

Huckster, *s.* क्षुद्रपण्यविक्रयिन्-विक्रेतृ *m.* **-v.** *i.* क्षुद्रपण्यानि वि-क्री 9 A.

Huddle, *v. t.* पिंडीकृ 8 U, सं-कॄ 6 P, संमिश्र् 10, संकुलीकृ, संपिंडयति (D.). 2 संक्षुभ् c.; ससंभ्रमं वि-धा 3 U or कृ. **-v.** *i.* संकुलीभू 1 P, संमिश्री-संकरी-भू, संकॄ pass., पिंडीभू. **-s.** संकुलं, संकरः, संक्षोभः, संकीर्णता.

Hue, *s.* रागः, रंगः, वर्णः, छाया, छवि *f.* 2 आक्रोशः; 'h. and cry' कलकलः, कोलाहलः, जनरवः, संहूति *f.*

Huff, *v. t.* विस्तॄ c., श्वि c., वृध् c., 2 सदर्पं निर्भर्त्स् or तर्ज् 10 A. **-v.** *i.* श्वि 1 P, स्फाय् 1 A, वृध् 1 A. 2 दृप् 4 P, विकत्थ् 1 A, प्रगल्भ् 1 A. **-s.** कोपः, रोषः, संरंभः; *See* **Anger.** 2 दर्पः, औद्धत्यं, निर्भर्त्सनं. 3 उद्धतः, दर्पाध्मातः, दांभिकः, विकत्थनः. **-er,** *s.* दांभिकः, शूरंमन्यः, विकत्थन.. **-ish,** *a.* **Angry, Arrogant,** q. v.

Hug, *v. t.* आलिंग् 1 P, आ-सं-श्लिष् 4 P, परिष्वंज् 1 A, बाहुभ्यां पीड् 10. *See* **Clasp.** **-s.** आश्लेषः, परिष्वंगः, आलिंगनं, उपगूहनं.

Huge, *a.* महत्, बृहत्, स्थूल, विशाल, विपुल, गुरु, बृहत्परिमाण, अतिमहत्-बृहत्. 2 (In body) स्थूल-काय-देह, बृहच्छरीर, महाकाय, विपुलांग (गी *f.*). **-ly,** *adv.* अतिमहत्, अत्यंतं, अतिमात्रं. **-ness,** *s.* अतिबृहत्त्वं, स्थूलता, विशालता.

Hulk, *s.* जीर्णनौका.

Hull, *s.* (पोतस्य) स्थूलभागः. 2 पुटः-टं, कोशः-षः, त्वच् *f.*, आवेष्टनं, तुषः (of grain).

Hum, *v. i.* गुंज् 1 P, वि-,रु 2 P, हुंकृ 8 U, अस्पष्टं निस्वन् 1 P or स्वन् 1 P. **-s.,** **-ming,** *s.* गुंजनं, गुंजितं, कलरवः-स्वरः, वि-,-रुतं-रावः, झंकारः, हुंकारः, हुंकृतं, अस्पष्टध्वनिः निस्वनः-नादः, कलकलः.

Human, *a.* मानुष (षी *f.*), पौरुषेय (यी *f.*), मनुष्यजातीय, मानवीय-व, gen. ex. by मनुष्य or नर in comp.; 'in h. accents' मनुष्यवाचा; 'uttered h. accents' मानुषीं गिरमुदीरयामास; 'h. nature' मानुष्यकं, पुरुषत्वं, नरस्वभावः, 'h. form' मानुषी तनुः, नररूपं; 'a h. brute' नरपशुः; 'h. kind' मनुष्य-नृ-जाति *f.*, मनुष्यवर्गः. **-ize,** *v. t.* वि-नी 1 P, शिष्टाचारं-सभ्यरीतिं शिक्ष् c. or शास् 2 P. **-ly,** *adv.* नरवत्, मानुषप्रकारेण. **-Humane,** *a.* दयालु, कृपालु, सदय, परहितकाम, परोपकारशील, अनुकंपिन्, करुणा-दया-शील, दयावत्, करुणार्द्र, दयार्द्र, परहितैषिन्, आपन्न-दीन-अनुकंपिन्; *See* **Kind.** **-ity,** *s.* दया, करुणा, कृपा, दयालुता, आपन्नानुकंपा, दीनवात्सल्यं, दयाशीलता, परहितेच्छा. 2 मानुष्यं-ष्यकं, मनुष्यता, मानुषता, मानवत्वं. 3 मनुष्याः, मनुष्यवर्गः-जातिः. **-ly,** *adv.* सदयं, सकरुणं, परहितेच्छया, सानुकंपं.

Humble, *a.* नीच, अपकृष्ट, अधम. 2 क्षुद्र, अल्पमति. 3 (In good sense) नम्र, विनीत, निरभिमान, विनत, सविनय, निरहंकार, अनुद्धत, दर्प-गर्व-अभिमान-हीन or रहित, नम्रचेतस्, विनयिन्, विनयशील-वृत्ति. 4 निःस्व, दरिद्र, दीन, दुर्गत, निर्धन, आपन्न; 'in h. days' आपत्समये, दरिद्रावस्थायां, आपदि; 'the friends of h. days' आपत्कालीनमित्राणि; 'to eat h. pie' मानं पृष्ठे कृ 8 U. **-v.** *t.* अव-नम् c. (नमयति), मन्नयति (D.), (सपदि विनयः मन्नयति मां U. 6); अभि-परा-भू 1 P, दर्प-गर्व-भंज् 7 P or हृ 1 P, नि-अव-पत् c., अप-कृष् 1 P, नम्रीकृ; 'thus completely h. ing the kings' इति राज्ञ

शिरसि वामपादमाधाय (R. vii. 70): 'h.-bee' भ्रमरः; *See* **Bee.** **-ed,** *a.* अभिभूत, भग्नदर्प, आत्त-गर्व-गंध, हृतगर्व; आनत, नम्रीकृत, पातित, अपकृष्ट. **-ing,** *s.* दर्प-मान-भंगः, अभिभवः. **-ness,** *s.* नीचता, अपकृष्टता, क्षुद्रता. 2 विनयः, नम्रता, अनहंकारः, अनभिमानः, अगर्वः, निरभिमानता, नम्रशीलता. **-Humbly,** *adv.* नीचैः, क्षुद्रतया, कृपणं. 2 सविनयं, नम्रतया, नम्रं, निरभिमानं, गर्वं विना, अनुद्धतं, नम्रचेतसा.

Humbug, *v. t.* प्रतॄ c., वंच् 10; *See* **Cheat.** **-s.** प्रतारणं-णा, वंचना, कपटः-टं, छलं.

Humdrum, *a.* निरस, जड, मंद, फल्गु. **-s.** मूढः, स्थूलधीः.

Humerus, *s.* प्रगंडः.

Humid, *a.* आर्द्र, क्लिन्न, उन्न, सरस, तिमित. **-ity.** आर्द्रता, क्लेदः, तेमः, सरसता.

Humiliate, *v. t.* गर्वं हृ 1 P or भंज् 7 P, अभिभू 1 P, अपकृष् 1 P; *See* **Humble.** **-ing,** *a.* दर्प-मान-हर. **-ion,** *s.* गर्व-दर्प-भंगः, अवमानना, मानभंगः-हानि *f.*, अभिभवः, अपकर्षः; दमनं; नियमनं.

Humility, *s.* विनयः, शालीनता, अगर्वः, अदर्पः, नम्रता, अनभिमानः, अनहंकारः, अनौद्धत्यं.

Humour, *s.* भावः, वृत्ति *f.*, मनोवृत्तिः, स्वभावः, शीलः-लं, प्रकृति *f.*; 'good h.' सद्भावः, सुशीलता, सौजन्यं; 'bad h.' वक्रभावः, दुःशीलं; 'joyous h.' आनंदवृत्तिः. 2 छंदः, छंदस् *n.*, मनोलौल्यं, बुद्धिचापल्यं, लहरी, चित्ततरंगः, चापलं. 3 क्लेदः, तेमः, आर्द्रता; स्नेहः, जलावसेकः. 4 रसः, जलं, धातुः (of the body); 'disorder of the three h. s.' दोषत्रयं, त्रिदोषं. 5 वैदग्ध्यं, रसिकता, रसः, सारस्यं, वैचित्र्यं. **-v. t.** (a person) चित्तवृत्तिं अनुवृत् 1 A, (अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये S. 2), छंदेन or छंदः (दं) अनुवृत्, भावं अनुरुध् 4 A or अनुप्र-विश् 6 P; (inclinations) अनुवृत्, अनुरुध्, अनुप्र-विश्. 2 अनुरंज् c., संतुष् c., आराध् c., प्र-सद् c., भज् 1 U, उपलल् 10, उपच्छंद् 10. **-ing,** *s.* अनुवर्तनं, अनुरोधः, छंदोनुवृत्तिः, भावानुप्रवेशः. **-ist,** *s.* वैहासिकः, हासकरः, विदूषकः, भंडः, परिहासशीलः, नर्मसचिवः. 2 रसज्ञः. **-ous,** *a.* हासकर (री *f.*), परिहासवत्, विनोदिन्, सरस, रसवत्, रसिक, हास्य, परिहासशील; विनोदनशील; oft. by परिहास or नर्म in comp.; 'a h. speech' परिहासः, परिहासजल्पितं, नर्मालापः, नर्मभाषितं. **-ously,** *adv.* सरसं, विनोदार्थं, परिहासपूर्वं. **-some,** *a.* वक्रभाव-शील, दुःशील, दुष्प्रकृति. 2 चलचित्त, लोलमति, चलप्रकृतिभाव; *See* **Fickle.**

Hump, *s.* ककुद् *f.*, ककुदः-दं (fig. also), अंसकटः (of bulls); गडुः, स्थगुः; 'having a h.' ककुद्मत्, ककुद्मिन्; 'h.-backed' कुब्ज, गडुल-र, कुब्जक, वक्रपृष्ठ, न्युब्ज.

Hunch, *s.* गडुः. 2 पिंडः. **-v. t.** अरत्निना तड् 10 or प्रहृ; 'h.-backed' **Hump-backed,** q. v.

Hundred, *a.* शतं; शतसंख्यक; 'by h. s' शतशः; 'in h. ways' शतधा; 'h.-fold' शतगुण *a.*; 'the life of man extends to h. years' शतायुर्वै पुरुषः. **-s.** शतं. **-th,** *s.* शततम (मी *f.*).

Hunger, *s.* क्षुधा, क्षुध् *f.*, बुभुक्षा, जिघत्सा, अशनाया, अशनायितं; 'h.-starved' क्षुत्क्षाम, क्षुधावसन्न. **-v. i.** क्षुध् 4 P (with dat.), भुज् desid. (बुभुक्षति-ते). 2 **Long,** q. v. **-Hungry,** *a.* क्षुधित, क्षुधार्त, क्षुधार्दित, क्षुत्पीडित, क्षुधातुर, जिघत्सु, बुभुक्षु, क्षुधाभ्याकुल, बुभुक्षित, अन्नार्थिन्, अशनायित; 'h. and thirsty' क्षुत्पिपासित. 2 अवसन्न, क्षीण, क्षाम, कृश.

Hunks, *s.* *See* ***Miser.***

Hunt, *v.* मृग् 10 A, मृगयां कृ 8 U, (मृगयायां) अनुधाव् 1 P, अनुसृ 1 P, अनुवृत् 1 A, अनुबंध् 9 P. 2 अन्विष् 4 P, निरूप् 10. **-s.,** **-ing,** *s.* मृगया, आखेटः, मृगव्यं, आच्छोदनं, पापर्द्धि *f.* 2 अनुसरणं, अन्वेषणं, मार्गणं, अनुधावनं; लाभेच्छा, लिप्सा; 'h.-dress' मृगयावेषः; 'h.-dog' विश्वकद्रुः, मृगयाकुक्कुरः. **-er, Huntsman,** *s.* व्याधः, लुब्धकः, मृगयुः, आखेटकः, मृगवधाजीवः; जीवांतकः; शाकुनिकः (of birds); वागुरिकः, जालिकः (with nets).

Hurdle, *s.* काष्ठावरणं.

Hurl, *v. t.* (तरसा-सवेगं) क्षिप् 6 P, वि-सृज्-मुच् 6 P, प्रास् 4 U, ईर् c., प्रेष् c., प्रहृ 1 P; 'h. down' नि अव-पत् c., अव-भ्रंश् c., अधःक्षिप्. **-s.** क्षेपः-पणं, पातनं. 2 तुमुलं, कोलाहलः. **-ing,** *s.* क्षेपणं; 'h. of stones' शिलावर्षः-आसारः.

Hurly-burly, *s.* तुमुलं, कोलाहलः, तुमुलरवः-कलकलः.

Hurrah, *interj.* जय or हर्ष-निस्वनः-शब्दः-नादः.

Hurricane, *s.* प्रकंपनः, महावातः, अतिवातः, प्रभंजनः, वात्या, प्रचंडवातः, वेगानिलः, वातालो, वात्यावेगः, चक्रवातः, जवानिलः, झंझावातः (with showers).

Hurry, *v. i.* त्वर् 1 A, शीघ्रं गम् 1 P, ससंभ्रमं गम्. **-v. t.** त्वर् c. (त्वरयति). 2 सत्वरं आकृष् 1 P or प्रणुद् 6 P, or प्रेर् c.; शीघ्रं सं-निः-पद् c. or वि-धा 3 U or साध् 5 P. **-s.** त्वरा, संभ्रमः, रभस् *n.*, रभसः, व्यग्रता, वेगः, आकुलत्वं, आ-सं-वेगः, त्वरितगति *f.*; 'why are you in such a h.' किमसि

संभ्रान्तेच (U. 3); 'in a h.' संभ्रांत, व्याकुल, व्यग्र. **-ed,** *a.* त्वरित, शीघ्र; 'a h. speech' निरस्तं वचः, त्वरितोदितं. **-edly,** *adv.* शीघ्रं, त्वरितं, सत्वरं, ससंभ्रमं, सरभसं, व्यग्रं.

Hurt, *v. t.* क्षि 5 P, तुद् 6 P, हिंस् 7 P, अर्द् 1 P or c., बाध् 1 A, व्यथ् c. (व्यथयति), द्रुह् 4 P, क्षण् 8 P, पीड् 10, अपकृ 8 U, विप्र-कृ, दु 5 P; 'does not h. one's reputation' यशः न क्षिणोति (R. II. 40). **-s** क्षतं, हिंसा, अपकारः, अपकृति *f.*, बाधा, पीडा, व्यथा. 2 अपायः, क्षयः, हानि *f.*, नाशः. **-ful,** *a.* पीडाकर (री *f.*), अपायावह, हिंसात्मक, बाधक, अपकारिन्, अहित-हानि-क्षति-कर. 2 हिंस्र, घातुक, शरारु. **-fully,** *adv.* हिंसापूर्वं, सापकारं. **-less,** *a.* अक्षत. 2 अहिंस्र, अनपकारिन्, अनुपद्रविन्.

Hurtle, *v. i.* संघट्ट 1 A, अभिसं-पत् 1 P. 2 सरभसं निष्क्रम् 1 U, 4 P or निर्गम् 1 P. 3 **Echo,** q. v.

Husband, *s.* पतिः, भर्तृ, उपयंतृ, परिणेतृ, परिग्रहीतृ, विवोढृ; कांतः, दयितः, धवः, नाथः, स्वामिन्; इष्टः, प्रियतमः, प्राणेशः, हृदयेशः, all *m.* (poetical words); 'h. and wife' दं(जं)पती, जायापती, भार्यापती; 'h.'s brother' देवरः, देवृ *m.*, देवलः; 'a second h.' दिधिषुः; 'h.'s sister' ननांदृ; 'h.'s brother's wife' यातृ; 'sister's h.' श्यालः, श्यालकः, आवुत्तः, भगिनीपतिः. **-v. t.** परिमितं व्यय् 10 (व्यययति), न विक्षिप् 6 P, परिमितव्ययं कृ 8 U. 2 कृष् 1 P, 6 U. **-less,** *a.* विधवा, अनाथा, पतिहीना, मृतभर्तृका, निर्णाथा. **-ry,** *s.* कृषि *f.*, कृषिकर्मन् *n.*, कर्षणं, कृषिविद्या, वैश्यवृत्ति *f.*, हलभृति *f.* 2 परिमितव्ययः, गृहकर्मनिर्वाहविद्या. **-Husbandman,** *s.* कृष(षि)कः, कर्षकः, कृषीवलः, क्षेत्रिकः, हालिकः; *See* **Farmer.** 2 वैश्यः, विश् *m.* ऊरुजः, ऊरव्यः, अर्यः, भूमिस्पृश् *m.*

Hush, *interj.* तूष्णीं भव, शांतं, वाचंयम-निःशब्द-*a.* भव. **-v. i.** शम् 4 P, प्र-उप-शम्, तूष्णीं भू, मौनीभू. **-v. t.** शम् c. (शमयति), निभृतं समा-धा 3 U; *See* **Conceal** also.

Husk, *s.* तुषः, त्वच् *f.*, कोशः, पुटः-टं, आवेष्टनं. 2 बुसं-सं, कडंगरः. **-v. t.** निस्तुषयति-निस्त्वचयति (D.), त्वचं हृ 1 P, निस्तुषीकृ 8 U. **-ed,** *a.* निस्तुष, त्वग्धीन. 2 सतुष, त्वग्युक्त. **-y,** *a.* सतुष, तुषवत्. 2 रूक्ष, कर्कश; 'in h. tones' रूक्षस्वरेण, बाष्पवृत्तिकलुषं.

Hussar, *s.* *See* **Cavalier.**

Hussy, *s.* बंधकी, पापा, दुष्टा स्त्री.

Hustle, *v. t.* **Drive away,** q. v. 2 संबाध् 1 A, संक्षुभ् c.

Hut, *s.* उटजः-जं, पर्णशाला, कुटीरः, तृणकुटी कायमानं.

Hutch, *s.* कुसू(सू)लः, धान्यकोष्ठः.

Huzza, *s.* जयध्वनिः, हर्षनादः-स्वनः.

Hyaline, *a.* काचमय, काचनिर्मित.

Hybrid, *a.* संकीर्णजाति, संकीर्ण, संकरजात, मिश्रज.

Hydra, *s.* जलव्याल.

Hydraulic, *a.* जल-प्रेरित-चोदित. 2 जलवाहिन्. **-s,** *s.* चलज्जलविज्ञानं.

Hydrocele, *s.* कोष-मुष्क-वृद्धि *f.*, फल or कोष-शोफः.

Hydrocephalus, *s.* मस्तिष्कशोथः, शिरोग्रहः.

Hydrography, *s.* समुद्रवेलादिविवरणं.

Hydromel, *s.* जलसंसृष्टं मधु.

Hydropathy, *s.* जलोपचारः, जलप्रयोगचिकित्सा.

Hydrophobia, *s.* जलसंत्रासः; अलर्काभिभवः, आलर्क.

Hydropsy, *See* **Dropsy.**

Hyemal, *a.* हैमंत (ती *f.*), शीतकालीन

Hyena, *s.* तरक्षुः-क्षः, तर्क्षुः.

Hygiene, *s.* आरोग्यविद्या.

Hygrometer, *s.* क्लेदमापकः.

Hymen, *s.* विवाहः, उद्वाहः. 2 विवाहाधिष्ठात्री देवता. **-eal,** *a.* विवाहीय, वैवाहिक-उद्वाहिक (की *f.*).

Hymn, *s.* स्तोत्रं, सूक्तं, गेयं, गानं, गीतं, स्तुतिगीतं; 'a chanter of h.s' उद्गातृ *m.*, सुम्नयुः. **-v. t.** गै 1 P, वर्ण् 10, गानद्वारेण स्तु 2 U or प्रशंस् 1 P; 'h.s praises' उपवीणयति (D.).

Hyp *s.* *See* **Dejection.**

Hyperbole, *s.* अतिशयोक्ति *f.*, अत्युक्तिः, वागुपचयः, सत्यातिक्रमः. **-ic, -ical,** *a.* अत्युक्तिपूर्वं, सत्यातिक्रामिन्. **-ize,** *v. t.* अत्युक्त्या वर्ण् 10 or कथ् 10.

Hyperborean, *a.* उत्तर, उदच्, उदीचीन, उत्तरीय.

Hypercritic, *s.* एकांततः गुणदोषनिरूपकः or छिद्रान्वेषिन् *m.*, दोषैकदृश् *m.*

Hypnotic, *a.* सुषुप्तिजनक.

Hypochondria, *s.* पित्तोन्मादः, वायुकोपः. 2 विषादः, उद्वेगः, अवसादः. **-cal,** *a.* पित्तोन्मादिन्, विषण्ण.

Hypocrite, *s.* दांभिकः, दंभिन् *m.*, कपटिन् *m.*, कापटिकः, कुहक-वृत्तिः, छद्म-कपट-वेशिन् *m.*, 'a religious h.' धर्मध्वजिन् *m.* लिंगवृत्तिः, बकवृत्तिः-व्रतः, आर्य-रूपः-लिंगिन् *m.*, छद्मतापसः. बैडालव्रतः. **-ical,** *a.* दांभिक, कपटिन्, छाद्मिक-कापटिक-दांभिक (की *f.*), छद्म-कपटin comp.; 'a h. sage' छद्मतापसः, कपटव्रतिन् *m.* छद्मवेषधारिन् *m.* **-ically,** *adv.* सदंभं, सकपटं, सव्याजं; दांभिकवत्, छद्मना. **-Hypocrisy,** *s.* दंभः, दांभिकता, कपटधर्म

धर्मोपधा, बकव्रतं, धर्मध्वजमात्रं, लिंगवृत्ति *f.*, कुहकवृत्तिः, छाद्मिकत्वं, कापट्यं, सव्याजता, आर्यरूपता.

Hypodermic, *a.* त्वगंतर्वत.

Hypotenuse, *s.* कर्णः, श्रुति *f.*

Hypothecate, *v. t.* आधिं गृहे गुप् 1 P; 'a h.-ed article' गोप्याधिः.

Hypothesis, *s.* उपन्यासः, प्रतिज्ञा, संकेतः, समयः. **-Hypothetic,-al,** *a.* उपन्यस्त, सांकेतिक (की *f.*), सोपन्यास, कल्पित. **-ally,** *adv.* सोपन्यासं, ससंकेतं, ससमयं, प्रतिज्ञाक्रमेण.

Hysterics, (**Hysteria,**) *s.* वातोन्मादः; हर्षमूर्च्छा, हर्षमोहः; मोहः, मूर्च्छा. **-Hysteric,-al,** *a.* हर्षमूर्च्छाल, मूर्च्छावत्; मोहोपहत, मूढ, मुग्ध.

I.

I, *pron.* अहं; oft ex. by अयं जनः (referring to persons, of any number or gender).

Ice, *s.* तुषार-हिम-संघातः, हिमसंहति *f.*, संहत-घनीकृत-जलं, हिमं; *See* **Snow** also; 'i.-berg' हिमपर्वतः-राशिः, हिमसंघातः, तुषारराशिः. **-v. t.** हिमीकृ 8 U, हिमेन शीतीकृ. **-Icy,** 'i.-cold', *a.* हिम, हिम्य, हैम (मी *f.*), तुषारवत्. 2 हिमशिशिर, शीतल; जड, शीत, शिशिर. 3 निरुत्साह, निःस्नेह, वीतराग. **-Icicle,** *s.* हिमकणः-बिंदुः.

Ichneumon, *s.* नकुलः, बभ्रुः, अंगूषः.

Ichor, *s.* पूयरक्तं.

Ichthyography, *s.* मत्स्यवर्णनं. **-Ichthyology,** *s.* मत्स्यशास्त्रं.

Icon, *s.* मूर्ति *f.*, देवताप्रतिमा. **-oclasm,** प्रतिमाभंगः. **-oclast,** *s.* देवताप्रतिमाभंजकः. **-ography,** *s.* प्रतिमालिखनं. **-ology,** *s.* प्रतिमाविद्या.

Idea, *s.* मति *f.*, बुद्धि *f.* 2 मतं, अभिप्रायः, आशयः, मनोगतं, भावः. 3 कल्पः, संकल्पः, कल्पना, भावना, वासना, बोधः; 'with the i. that' ex. by बुद्ध्या in comp. or इति कृत्वा. **-Ideal,** *a.* मनःकल्पित, मानस (सी *f.*), काल्पनिक-मानसिक (की *f.*), चित्तोद्भावित; मनसिज, मनोभव. **-s.** मनोरथसृष्टि *f.*; oft ex. by परम; 'i. of beauty' परमलावण्यं. **-ism,** *s.* बाह्यशून्यवादः. **-ly,** *adv.* मनसा, कल्पनया, भावनापूर्वं.

Identical, *a.* तद् (*pron. a.*) with एव, अनन्य, अनन्यरूप, निर्विशेष, अभिन्न, अव्यतिरिक्त, अभिन्नरूप, सम, समान, निरस्तभेद, आत्मन्-रूप in comp.; 'i. with the world' जगदात्मक विश्वरूप; 'becoming i. with Brahman' ब्रह्मसायुज्यं प्राप्त, ब्रह्मलीनः. **-ly,** *adv.* अभिन्नं, समं, निर्विशेषं. **-Identify,** *v. t.* समीकृ 8 U, तुल्यीकृ, अनन्यीकृ. 2 तदेव इति प्रति-पद् c. or वि-भू c., or अभि-ज्ञा 9 U, तुल्यत्वेन परिच्छिद् 7 P. **-v. i.** समीभू. **-ication,** *s.* समीकरणं, एकरूपता, सायुज्यं, अभिज्ञानं, विभावनं; 'i. with Brahman' ब्रह्मसायुज्यं, ब्रह्मभूयं. **-Identity,** *s.* ऐक्यं, साम्यं, संवादः, निर्विशेषः, अभेदः, अनन्यता, तादात्म्यं, सारूप्यं, सरूपता, आत्मता, सायुज्यं; 'i. of thoughts' चित्तैक्यं, एकचित्तता; 'i. of class' सावर्ण्यं, सजातित्वं; 'i. of hand' वर्णसंवादः.

-eology, *s* मानसशास्त्रं.

-…m, *s.* वाक्पद्धति-रीति *f.*, वाग्व्यवहारः, वाक्कृतंप्रदायः, विशिष्टस्वरूपं. **-atic,** *a.* Ex. by (*s.*).

Idiosyncrasy, *s.* देहस्वभावः, जातिस्वभावः.

Idiot, *s.* जडः, मूर्खः, अनात्मज्ञः, मूढः, वैधेयः, बालिशः, अज्ञः, निर्बुद्धिः. **-ic,** *a.* जड, मूढ, मूर्ख, हतज्ञान, बुद्धिविकल. **-Idiocy,** *s.* मूढता, मूर्खता, जाड्यं, अज्ञता, बालिशता; *See* **Fool,-ish, Folly.**

Idle, *a.* अलस, कर्म or कार्य-विमुख or पराङ्मुख (खी *f.*), कर्मद्वेषिन्, आलस्यशील, अनुद्योगशील. 2 अव्यापृत, निरुद्योग, निर्व्यवसाय, कर्म or कार्य-शून्य or रहित, निर्व्यापार, निरुद्यम, निश्चेष्ट; उदासीन, निरुत्साह. 3 निरर्थक, निष्प्रयोजन, व्यर्थ, मोघ; 'it were i. to talk of friend or foe in Govinda' गोविंदविषये मित्रामित्रकल्पनं व्याघातः, व्याहतं एव; 'to be i.' उदास् 2 A; 'i. talk' वृथालापः, वृथाकथा. **-v. t.** (time) उदास्, कालं मुधा क्षै c. (क्षपयति) or नी 1 P or अतिवह् c., कालं हृ 1 P or क्षिप् 6 P, कालक्षेपं कृ 8 U, अलस-निर्व्यापार -*a.* भू. **-er,** *s.* निर्व्यापारः, कालक्षेपकः, कार्यद्वेषः, सुखनिरीक्षकः. **-ness,** *s.* आलस्य, कार्यद्वेषः, कार्यविमुखता, उदासीनता. 2 अनुद्योगः, अव्यापारः, कार्यशून्यता, कालक्षेपः-पणं. **-Idly,** *adv.* आलस्येन, अलसवत. 2 निरुद्योगं, निर्व्यापारं. 3 निरर्थकं, व्यर्थं, वृथा, मुधा.

Idol, *s.* (देव-) प्रतिमा-मानं, मूर्ति *f.*, दैवतं, देवता, देवताविग्रहः, प्रतिकृति *f.* 2 (*Fig.*) आराध्यदेवता; 'attendant on an i.' देवलः, देवाजीवः-विन् *m.* **-Idolater,** (**Idolatrous**) *s.* मूर्ति-प्रतिमापूजकः-अर्चकः-उपासकः, देवतार्चकः, प्रतिमासेविन् *m.* **-Idolatry,** *s.* प्रतिमा or मूर्ति-पूजा or अर्चनं, देवतार्चनं, प्रतिमासेवा देवतोपासना, मूर्तिसेवा-उपासनं. **-Idolatrize,** *v. i.* प्रतिमां पूज् 10 or अर्च् 1 P. 10. **-Idolize,** *v. t.* देवतां इव आराध् c.

देववत् पूज्, or भज् 1 U; एकांततः प्री-अनु-रंज्-pass., अत्यंतानुरक्त-*a*. भू, अतिप्रेम कृ 8 U.

Idoneous, *a*. *See* **Fit.**

If, *conj*. यदि, चेत (not at beginning); 'if so' यद्येवं, एवं स्थिते; 'if not' नोचेत, अन्यथा, यदि न; 'as if' इव.

Igneous, *a*. अग्निमत्, आग्नेय-अग्निमय (यी *f*.).

Ignis-Fatuus, *s*. मिथ्याग्निः, मिथ्यादीप्ति *f*., दीप्त्याभासः.

Ignite, *v. t*. ज्वल् c., दीप् c., सं-इंध् 7 A, संधुक्ष् 10, दह् 1 P, तप् c. **–***v. i*. ज्वल् 1 P, दीप् 4 A, सं-इंध् pass. **–ion,** *s* दीपनं, ज्वलनं, इंधनं.

Ignoble, *a*. अकुलीन, हीनजाति-वर्ण, नि-अप-कृष्ट, नीच, अधम, जघन्य, अनार्य; *See* **Base.** 2 अकीर्तिकर-लज्जाकर (री *f*.). **–Ignobly,** *adv*. अनार्यवत्, नीच-अधम-वत्.

Ignominy, *s*. **Disgrace,** q. v. **2** अपकर्षः, अवज्ञा, अपमानः, कलंकः, अप्रतिष्ठा, तिरस्कारः, परिभवः. **–ious,** *a*. अपकीर्ति-लज्जा-कलंक-कर (री *f*.), गर्ह्य, कलंकावह, वाच्य.

Ignoramus, *s*. अज्ञः, पंडितंमन्यः.

Ignore, *v. t*. न ज्ञा 9 U, न स्वीकृ 8 U. **–ance,** *s*. अज्ञानं, अविद्या, ज्ञानाभावः, अबोधः, मोहः. **2** ज्ञानहीनता, अनभिज्ञता, अज्ञता, अनभिज्ञानं, निर्बुद्धित्वं; 'difference imagined by i.' अविद्याकल्पितभेदः. **–ant,** *a*. अज्ञ, अवेदिन्, अज्ञान, अनभिज्ञ, oft. ex. by not 'know', q. v. **2** अप्राज्ञ, अविज्ञ, अपंडित, दुर्बुद्धि, निर्बुद्धि, अ-निर्-बोध, विद्या-ज्ञान-प्रज्ञा-बोध-हीन-शून्य-रहित, दुर्मति, अविद्वस्. **–antly,** *adv*. अज्ञानतः, अज्ञानेन, अज्ञान-अबोध-पूर्वं.

Iguana, *s*. गोधा, गौधारः.

Iliac, *a*. आंत्रिक (की *f*.), अंत्र in comp.; 'i. pain' अंत्रशूलं, शूलव्याधिः-रोगः.

Ill, *a*. दुष्ट, पाप, असत्, असाधु, गर्ह्य, खल, कुत्सित, अभद्र, अमंगल, अशुभ, gen. ex. by दुर्, कु, अप, वि, कद्, pr.; *See* **Bad;** oft. by अ in comp. **2** अस्वस्थ, अस्वस्थ-असुस्थ-शरीर, असुस्थ, असुस्थित, व्याधित, सामय, रोगिन्; gen. ex. by आर्त, ग्रस्त, आतुर, पीडित in comp., 'i. with fever' ज्वरार्त, ज्वरपीडित. **–***s*. दुष्टता, खलता, असाधुता. **2** पापं, दुराचारः, अधर्मः, दुर्वृत्तं, दोषः, अपराधः. **3** अनिष्टं, अशुभं, अमंगलं, अकुशलं, अभद्रं, दुःखं, दुर्गति *f*., आपद्-विपद् *f*., व्यसनं, उत्पातः, अनर्थः, अरिष्टं, अनिष्टपातः, कष्टः-ष्टं, अपायः. **4** अपकारः, अपकृति *f*., अहितं, अपायः, क्षति-हानि *f*., क्षयः, अपचयः. **5** रोगः, व्याधिः, आमयः, पीडा, उपतापः, अस्वास्थ्यं, *See* **Disease.** **–***adv*. असाधु, अनार्यं, असम्यक्, दुष्टं. **2** दुःखेन, कष्टेन, कृच्छ्रेण; in comp. words, ex. by दुर्, कु, अप, वि, कद्, अ, दुष्ट, पाप; 'i.-advised' अपरीक्षित, अविमृश्य कृत; 'i.-affected' वि-अप-रक्त, द्रोहबुद्धि, अहितैषिन्; 'i.-arranged,-ordered,-regulated' दुष्क्रम, दुर्विरचित, अव्यवस्थित; 'i.-behaved,-bred,-natured' अविनीत, दुःशील, दुर्वृत्त, कुशील, अविनय, दुर्विनीत, अशिष्ट, असभ्य, दुराचार, पाप, कुवृत्ति, विनयापेत; 'i.-breeding' अविनयः, दुःशीलता, असभ्यता, विनयप्रमाथः, दुर्वृत्ति *f*., दुराचारः; 'i.-conditioned' दुर्गत, दुःस्थित; 'i.-dressed' दुर्वासस्, कुप्रावृत; 'i.-fame' अयशः, अपकीर्ति *f*., अप्रतिष्ठा; 'i.-fated' दुर्भाग्य, मंदभाग्य, दुर्दैव, दैवोपहत, दुर्दैवग्रस्त-उपहत; 'i.-favoured,-formed,-shaped' अप-कु-रूप, कदाकार, दुर्दर्शन; 'i.-fitted' अयोग्य, अनर्ह, अनुचित; 'i.-gotten' अन्यायार्जित; 'i.-grounded' अमूलक; 'i.-judged' अविमृश्य-अविचार्य-कृत, अनालोचित; 'i.-judging' विवेकशून्य; निर्विवेक; 'i.-looking' दुर्दर्शन, कुरूप; 'i.-luck' दुर्दैवं, दुर्भाग्यं, मंदभाग्यं, दैवविपर्यासः-दुर्विपाकः, दुर्जातं, अनिष्टं; *See* (*s*.); 'i.-nature,-temper' दुःशीलं, दुष्प्रकृति *f*., वक्रभावः-शीलं, वामशीलं, भावप्रतीपता, वामशीलता, स्वभाववक्रता 'i.-natured, -tempered' दुष्प्रकृति, वक्र वाम-शील, दुष्ट-खल-स्वभाव, कटु-कर्कश-प्रतीप-स्वभाव, कु-दुः-शील; 'i.-omened' अशुभसूचक, अनिष्टशंसिन्, अनिष्टलक्षण; 'i.-sounding' अपस्वर, वि-कु-स्वर, कटु; 'i.-timed अकाल, अप्राप्तकाल, अप्राप्तावसर, अनवसर, आकालिक (की *f*.); 'i.-treat' विप्र-अप-नि-कृ 8 U, उपद्रु 1 A, पीड् 10, अर्द् 1 P or c., खलीकृ; 'i.-treatment' अपकारः, पीडा, अर्दनं; *See* (*s*.); 'i.-turn' अपकारः, पापं, अप्रियं अहितं, हिंसा, द्रोहः; 'i.-will' दुष्टभावः-बुद्धिः, द्रोहः, द्वेषः, मात्सर्यं, असूया. **–ness,** *s*. रोगः, व्याधिः, आमयः, रुजा, अस्वास्थ्यं, पीडा, बाधा, आर्ति *f*., क्लेशः, उपतापः, दुःखं, विकारः, विकृति *f*.; 'dangerous i.' जीवितसंशयः, सान्निपातः.

Illapse, *s*. सहसा प्रवेशः or आक्रमणं. **–***v. i*. सहसा प्रविश् 6 P or पत् 1 P.

Illation, *s*. अनुमानं, तर्कः. **–Illative,** *a*. आनुमानिक (की *f*.). **–ly,** *adv*. अनुमानेन, अपोहेन.

Illegal, *a*. नियम-विधि-विरुद्ध, शास्त्र-स्मृति-व्यवहार-न्याय-विरुद्ध, स्मृत्यपेत, अधर्म्य, अन्याय्य, न्याय-धर्म-रोधिन्, अविधि. **–ity,** *s*. विधि-धर्म-शास्त्र-नियम-विरोधः, अन्याय्यता, अधर्म्यता, अव्यवस्था, नियम-व्यवस्था-विधि-भंगः. **–ly,** *adv*. नियम-विधि-विरुद्धं.

Illegible, *a.* दुर्वाच्य, अव्यक्ताक्षर, अस्पष्टाक्षर, अस्पष्ट-अव्यक्त-वर्ण.

Illegitimate, *a.* अन्याय्य, विधिविरुद्ध; *See* **Illegal. 2** विजात, जारजात, जारज, असतीप्रसूत, अनौरस, विजन्मन्, जारोत्पन्न. 3 कृत्रिम. कृतक, कल्पित; 'an i. child' अनौरसः-सी, जारजः-जा, दासीपुत्रः, कौलटेयः-यी, कौलटेरः-री, बंधकी-उपपत्नी-सुतः-ता, बंधुलः, कौलटिनेयः-यी. **-ly,** *adv.* विजन्मना; अधर्मेण. **-Illegitimacy,** *s.* विजन्मन् *m.*, वैजात्यं, अनौरसत्वं.

Illiberal, *a.* अनुदार, कृपण, कृपणबुद्धि-चेतस्-स्वभाव, (lit. and fig.); अत्याग-अदान-शील, अवदान्य. **-ity,** *s.* अत्यागः, अवदान्यत्वं, अनौदार्यं, कार्पण्यं, नीचता, दीनता.

Illicit, *a.* प्रति-नि-षिद्ध, अधर्म्य, अन्याय्य, नियम-धर्म-विरुद्ध, व्यवहारविरोधिन्.

Illiterate, *a.* अशिक्षित, अप्रबुद्ध, असंस्कृत, अव्युत्पन्न, विद्या-ज्ञान-हीन, निरक्षर, अनक्षर, असंस्कृतचित्त.

Illimited,-able, *a.* निरवधि; अनंत, अमेय, असीम, अमित, अमर्याद; *See* **Endless.**

Illogical, *a.* अयुक्तिसिद्ध, न्यायविरुद्ध-विपरीत, अन्यायानुसारिन्, अन्याय्य, अतार्किक (की *f.*); 'i. conclusion' अपसिद्धांतः, अविनिगमः. **-ly,** *adv.* न्यायविरुद्धं.

Illude, *v. t.* वंच् 10, मुह् c., प्रतॄ c.; *See* **Cheat. -Illusion,** *s.* माया, प्रपंचः, इंद्रजालं, अलीकता, अविद्या; *See* **Delusion. Illusive, -Illusory,** *a.* मायिन्, अलीक, ऐंद्रजालिक; *See* **Delusive.**

Illume, Illumine, Illuminate, *v. t.* द्युत् c., प्रकाश् c. उद्भास् c., उद्दीप् c., वि-,राज् c., भ्राज् c., उज्ज्वल् c. **2** (पत्राणि) रंज् c. **-Illumination,** *s.* उद्भासनं, द्योतनं, प्रकाशनं, उज्ज्वलनं, दीप्ति-द्युति-*f.*, भ्राजिष्णुता. **2** (i. s) दीपालि *f.*, दीपमाला-समूहः, दीपोत्सवः. 3 पत्ररंजनं. **-Illuminator,** *s.* द्योतकः, प्रकाशकः, दीपकः. **2** पत्ररंजकः.

Illustrate, *v. t.* व्या-ख्या 2 P, व्या-चक्ष् 2 A, स्पष्टीकृ 8 U, विवृ 5 U; उदा-हृ 1 P, निर्दिश् c., निदर्शनेन व्या-ख्या, व्यक्ती-विशदी-कृ, चित्रेण स्पष्टीकृ, प्रकाश् c., द्युत् c., शुभ् c., दीप् c, चित्रादिना शुभ् c. **-ion,** *s.* उदाहरणं, दृष्टांतः, निदर्शनं, व्याख्या-ख्यानं, प्रकाशनं, निरूपणं. **-ive,** *a.* प्रकाशक, दार्ष्टांतिक (की *f.*). **-or,** प्रकाशकः, निदर्शकः, व्याख्यातृ *m.*

Illustrious, *a.* विश्रुत, ख्यात, प्रथित, प्रसिद्ध, महायशस्क; *See* **Famous. 2** विशिष्ट, उत्तम, उत्कृष्ट, परम, प्रमुख, महत्. **-ly,** *adv.* विश्रुतं, प्रथितयशसा, विशिष्टतया. **-ness,** *s.* विश्रुति-ख्याति- *f.*

Image, *s.* प्रतिमा, मूर्ति *f.*, प्रतिकृति *f.*-मूर्तिः-मानं-रूपं, प्रतिच्छंदकः **2** प्रतिबिंबं, बिंबं, छाया, प्रतिच्छाया, प्रतिच्छंदः-दकं; 'this youth is the complete i. of Râma' रामस्याकृतिरस्मिन् शिशौ संपूर्णा प्रतिबिंबिता (U. 4). **3 Idea,** q. v.; 'iron i.' लोहप्रतिमा, स्थूणा, सू(शू)र्मी. **-v. t.** मनसा क्लृप् c. or चिंत् 10, प्रतिबिंबयति (D.); 'i. various shapes' तैस्तैराकृतिविशेषैरनुगताः (Mr. 5). **-ery,** *s.* मनः-कल्पना-सृष्टि *f.*-संकल्पः, भावना, वासना. **2** उपलक्षणं, लक्षणा. **3** आभासः, आडंबरः, अनुकारः.

Imagine, *v. t.* मनसा क्लृप् c., सं-परि°; सं-वि-भू c., सृज् 6 P, ध्यै 1 P. **2** मन् 4 A, गण् 10, चिंत् 10, तर्क् 10, उत्प्रेक्ष् 1 A, बुध् 1 P, अव-इ 2 P, अवगम् 1 P, उपलभ् 1 A. **-able,** *a.* संभाव्य, चिंतनीय, बोधगम्य; 'with all i. ease' मनसोऽप्यगोचरीभूतया-मनसाऽप्यकल्प्यमानया-लीलया. **-ary,** *a.* मनःकल्पित, वासना-भावना-सृष्ट, मनोरथसृष्ट, मानस (सी *f.*), काल्पनिक (की *f.*), संकल्पज. **2** अमूलक, असत्य, मायामय (यी *f.*). **-ation,** *s.* भावना-नं, कल्पना-नं, संकल्पः, वासना, मनःकल्पना. **2** (Faculty of i.) कल्पना-तर्क-शक्ति *f.*, भावना, उपलब्धि *f.* **-ative,** *a.* कल्पक, विभावक, भावनापर, कल्पनाशील.

Imbecile, *a.* दुर्बल, अशक्त, क्षीणबल; *See* **Feeble. 2** (In mind) न्यूनबुद्धि, अल्प-विकल-मति, बालिश, कृपणबुद्धि. **-ity,** *s.* दौर्बल्यं, न्यूनबुद्धिता, बालिशत्वं.

Imbed, *v. i.* अंतर्गम् 1 P, निविश् 6 P.

Imbibe, *v. t.* नि-पा 1 P, आ-पा, शुष् c. **2** (Fig.) अधिगम् 1 P, मनसा ग्रह् 9 U or आकल् 10 (कलयति) or उपलभ् 1 A.

Imbricate, *v. t.* आतिव्याप् 5 P.

Imbroglio, *s. See* **Embroglio.**

Imbrue, *v. t.* सिच् 6 P, लिप्, 6P, उक्ष् 1 P, क्लिद् c.; अंज् 7 P, दिह् 2 U; 'i. ed with blood' रक्ताक्त, रक्तक्लिन्न.

Imbue, *v. t.* अभिरंज् c. **2** शास् 2 P, उपदिश् 6 P, शिक्ष् c.

Imitate, *v. t.* अनुकृ 8 U (oft. with gen.), अनुगम्-सृ 1 P, अनु-इ-या 2 P, अनुवृत् 1 A, अनुवि-धा 3 U, अनुवद् 1 P, अनुहृ 1 P, विडंब् 10. **-ion,** *s.* अनुकारः-करणं, अनुकृति *f.*, विडंबनं, अनुवृत्ति *f.*, अनुसरणं. **2** उपमानं, प्रतिरूपं, सादृश्यं. **-ive,** *a.* अनुकरणशील, अनुकारिन्, अनुगामिन्. **-or,** *s.* अनुकर्तृ *m.*, अनुकारकः, अनुयायिन्-अनुकारिन् *m.*, अनुयातकः.

Immaculate, *a.* निष्कलंक, निर्मल, अकल्मष, अनघ, निर्दोष, विमल.

Immanent, *a.* अंतर्भव, अंतरस्थ.

Immaterial, *a.* अमूर्त, निरवयव, अशरीरिन्, अमूर्तिमत्. 2 लघु, अगुरु, अगुर्वर्थ, यत्किंचित्, निष्प्रयोजन, अनावश्यक (की *f.*), निरर्थक. **-ism,** *s.* निराकारवादः. **-ist,** *s.* निराकारवादिन् *m.* **-ity,** *s.* अमूर्तता, अशरीरता. **-ly,** *adv.* निरर्थकं, निष्प्रयोजनं.

Immature, *a.* अपक्व, अपरिणत, असंपूर्णकाल, असिद्ध, अप्राप्तकाल आकालिक(की *f.*). **-ly,** *adv.* अपक्वं, अपरिणतं, अप्राप्तकालं, अतिशीघ्रं, परिणामकालात् प्राक्. **-ity,-ness,** *s.* अपाकः, अपरिपाकः, अपरिणामः, अप्रौढता, अप्राप्तकालता.

Immeasurable, *a.* अमेय, अमित, अपरिमाण, दुर्मेय, महत्, बहु, अति pr.

Immediate, *a.* अनंतर, अव्यवहित, निरंतर, अव्यवधान. 2 तात्कालिक (की *f.*), सद्यस्क, अचिर, शीघ्र; better by 'i. ly.' 3 सन्निहित, उपस्थित, आसन्न, निकट. **-ly,** *adv* सद्यः, सपद्येव, समनंतरमेव, सपदि तत्क्षणात्, तत्काले, सद्य एव, झटिति, द्राक्, आशु, अविलंबितं, अचिरादेव; oft. by एव or मात्र; 'i. after he had spoken' तस्मिन्नुक्तवत्येव; मुक्तमात्रे सायके &c.

Immedicable, दुरुपचार, अचिकित्स्य.

Immemorable, *a.* अस्मर्तव्य.

Immemorial, *a.* अस्मार्त, स्मरणातिक्रांत, अतिप्राचीन, अनादि; 'i. succession' अनादिपरंपरा; 'from times i.' अनादिकालात्, अस्मर्तकालात्.

Immense, *a.* अत्यंत, अपरिमेय, अतिमात्र, अनंत, अपरिमाण, अमित, अतिमर्याद, दुर्मेय; महत्, बृहत्, सु-अति-महत्, अतिबृहत्. **-ly,** *adv.* अत्यंतं, अतिमात्रं. **-ity,** *s.* आनंत्यं, अमितता, अपरिमाणत्वं, महत्त्वं, सुमहत्त्वं. **-urable,** *a. See* **Immeasurable.**

Immerge, Immerse, *v. t.* अवगाह् c., निमस्ज् c. (मज्जयति), आप्लु c., जले प्रविश् c. **-ed,** *a.* मग्न, नि-अभिनि-निविष्ट, व्यापृत, लीन, आसक्त, निष्ठ-पर-तत्पर-in comp.; *See* **Fixed, Intent. -Immersion,** *s.* निमज्जनं, अवगाहः-हनं, आप्लावः, स्नानं, अभिषेकः. 2 मग्नता, निष्ठा, तत्परता, अभिनिवेशः.

Immethodical, *a.* क्रमहीन, क्रमविरुद्ध, अव्यवस्थित. **-ly,** *adv.* क्रमविरुद्धं, अक्रमेण.

Immigrate, *v. i.* देशांतरं अधिवस् 1 P or अध्यास् 2 A (with acc.). **-ion,** *s.* देशांतराधिवासः, देशत्यागः. **-Immigrant,** *s.* देशांतराधिवासिन् *m.*

Imminent, *a.* उपस्थित, आसन्न, संनिकृष्ट, उपनत, निकट-आसन्न-वर्तिन्; 'a drought is i.' अनावृष्टिः संपद्यते लग्ना (P. I. 7). 2 आत्ययिक (की *f.*), जीवितसंशयावह, 'he stood in i. peril of death' महति जीवित, संशये अवर्तत.

Immit, *v. t. See* **Place.**

Immobile, *a.* स्थिर, निश्चल, अचल, निष्कंप.

Immoderate, *a.* अमित, अपरिमित, अमर्याद, अत्यंत,अतिमात्र, अत्यधिक, सु-अति pr. **-ly,** *adv.* अतिमात्रं, अत्यंतं, सु-अति-pr. **-ion,** *s.* अमर्यादा, मर्यादातिक्रमः, अत्याचारः, अतिरेकः, अतिशयः.

Immodest, *a.* धैयात, निर्लज्ज, निस्त्रप, अविनीत, प्रगल्भ, धृष्ट, लज्जा-व्रीडा-त्रपा-हीन. 2 अश्लील, ग्राम्य, अवाच्य, अशुद्ध, अशुचि. 3 असाधु, असद्वृत्त, पांसुल, व्यभिचारिन्. **-ly,** *adv.* निर्लज्जं, प्रगल्भं, धृष्टवत्, अश्लीलं. **-y,** *s.* धैयात्यं, अविनयः, प्रागल्भ्यं, धृष्टता निर्लज्जत्वं.

Immolate, *v. t.* (यज्ञे) हन् 2 P, विशस् 1 P, उपहारीकृ 8 U, हत्वा उत्सृज् 6 P. बलिं दा 3 U or कृ, आलभ् 1 A, सं-ज्ञा c (ज्ञपयति); 'i. oneself' प्रेतेन सह आत्मानं दह् 1 P, सह गम्. **-ion,** *s.* उपहारीकरणं, उपहारः, बलिदानं, आलंभः, संज्ञपनं, उत्सर्गार्थं वधः or विशसनं.

Immoral, *a.* असाधु, दुश्चरित्र, दुर्वृत्त, दुराचार-पापकर्मन्, व्यभिचारिन्, व्यसनिन्, पापिन्; दुष्ट, धर्मविरुद्ध, अपुण्य, अशुचि, पाप. **-ity,** *s.* असाधुता, दुर्वृत्तता; व्यसनं, अधर्मः, पापं, पापचरितं, दुश्चरितं, व्यभिचारः. **-ly,** *adv.* धर्मविरुद्धं, दुराचारेण.

Immortal, *a.* अमर, अमर्त्य, जरामरणरहित. अक्षय, अजर, निर्जर. अनश्वर, अविनाशिन्, नित्य, सनातन (नी *f.*), अनंत, शाश्वत (ती *f.*), सदास्थायिन्. **-ity,** *s.* अमरता-त्वं अनश्वरता, आनंत्यं, नित्यता. **-ize,** *v. t.* अमरी-अक्षयी-कृ 8 U; better by (*a.*). **-ly,** *adv.* अजरं, अक्षयं, अनश्वरं, शाश्वतं.

Immoveable, *a.* अचल, स्थिर, स्थावर, अचर, अजंगम.

Immune, *a.* मुक्त, रहित; ex. by अ or निर् pr. अगम्य, अक्षम, अनर्ह. **-ity,** *s.* मुक्ति *f.*, मोक्षः. 2 अभावः, विरहः न्यूनता, राहित्यं; oft. by अ or निर् pr.; 'i. from danger' अभयं, निर्भयत्वं.

Immure, *v. t.* नि-अव-रुध् 7 U, बंध् 9 संयम् 1 P, कारायां क्षिप् 1 P. 2 परिवृ 5 U, परिवेष्ट् 1 A or c.

Immutable, *a.* अव्यय, निर्विकार, नित्य, अविक्रिय, विकाराक्षम, स्थिर,निर्विकल्प, अपरिवर्तनीय. **-Immutability,** *s.* अविकारः, नित्यता, अव्ययः.

Imp, *s.* पिशाचः, भूतः; *See* **Devil, Demon.**

Impact, *s.* संस्पर्शः, संपर्कः, सम-प्रति-घातः, संघट्टः.

Impair, *v. t.* ह्रस् c., अप-चि 5 U, क्षि 1, 5 P or c., नश् c., विलुप् c., लघूकृ 8 U, ऊन् 10, उप-हन् 2 P, दुष् c. (दूषयति), अल्पीकृ, विकलीकृ, क्षिणीकृ. 2 तेजः-बलं-हृ 1 P, दुर्बलीकृ. **-ed,** *a.* ह्रसित, क्षीण, विकल, अपचित, उपहत, विशीर्ण, लुप्त, न्यूनी-विकली-कृत; 'i. in strength' क्षीणबल, निःसत्व. **-ing,** *s.* क्षयः, ह्रासः, अपचयः, अवसादः; वैकल्यं, न्यूनता, लोपः.

Impale, *v. t. See* **Empale.**

Impalpable, *a.* अस्पृश्य, अग्राह्य, स्पर्शाव्यक्त, इंद्रियागोचर, अव्यक्त, अतिसूक्ष्म.

Imparity, *s.* वैषम्यं, भेदः, असाम्यं.

Impart, *v. t.* दा 3 U, 1 P, प्रति-पद् c., सम्-ऋ c. (अर्पयति), निक्षिप् 6 P, संक्रम् c., ग्रह् c., वि-तॄ 1 P (with loc.), संसृज् 6 P, सुवर्णविकारा अर्पीतौ न सुवर्णमात्मीयेन धर्मेण संसृजंति (S. B. 431) 'do not i. to gold their properties'. 2 नि-आ-विद् c., कथ् 10; प्रकाश् c., वि-ज्ञा c (ज्ञापयति), ख्या 2 P or c. 3 संचर् c., संक्रम् c.

Impartial, *a.* अपक्षपातिन्, समक्रिय, समदर्शिन्, समवृत्तिभाव, उदासीन, मुक्तसंग, सर्वसम, पक्षपातहीन, न्यायवर्तिन्, न्याय्य, धर्म्य. **-ity,** *s.* अपक्षपातः, धर्मः, समता, निःसंगता, औदासीन्यं, न्याय्यता. **-ly,** *adv.* न्यायेन, निःसंगं, अपक्षपातेन.

Impartible, *a.* अविभाज्य, अवंटनीय.

Impassable, *a.* अगम्य, अलंघ्य, दुस्तर, दुर्गम, दुस्तार्य, गहन, संबाध, संकट.

Impassible, *a.* अ-निः-चेतन, सुखदुःखाक्षम.

Impassioned, *a.* अनुरक्त, अनुरागवत्, रागान्वित, बद्धभाव, सानुराग, प्रीत्याकृष्ट, आसक्तचित्त. 2 सरस, रसिक, रागयुक्त, रागिन्; 'what an i. strain अहो रागपरिवाहिणी गीतिः (S. 5).

Impassive, *a.* विकार-अक्षम-अगम्य.

Impatient, *a.* (For) उत्सुक, व्यग्र सोत्कंठ, प्रसित, उत्क; *See* **Eager.** 2 (Of) असह, असहन, अक्षमिन्, असहिष्णु, अक्षम. 3 अधीर, कालहरणाक्षम, अमर्षण, अतितिक्षु. **-ly,** *adv.* अधीरं, सोत्सुकं, व्यग्रं, सावेगं, अक्षांत्या. **-Impatience,** *s.* अधीरता, औत्सुक्यं, व्यग्रता, उत्कंठा, अक्षमा, असहत्वं.

Impawn, *v. t. See* **Pledge.**

Impeach, *v. t.* अभियुज् 7 A, 10, अभिशंस् 1 P, अपवद् 1 U, आधृष् c. **-er,** *s.* अभियोगिन्-योक्तृ *m.* **-ment,** *s.* अभियोगः, अभिशंसनं.

Impeccable, *a.* अपाप, निर्दोष.

Impecunious, *a.* दरिद्र, अकिंचन, निर्धन.

Impede, *v. t.* रुध् 7 U, प्रतिबंध् 9 P, वि-प्रति-हन् 2 P, नि-वृ c., स्तंभ् 9 P, or c., बाध् 1 A, कुंठयति (D.). **-Impediment,** *s.* विघ्नः, प्रत्यूहः, अंतरायः, व्याघातः, उपरोधः, प्रतिबंधः; *See* **Obstacle.**

Impel, *v. t.* नि-प्र-उद्-युज् 10, प्रवृत् c., प्रोत्सह् c., उत्तिज् c., प्रेर् c., नुद् 6 P or c., प्रणुद्, प्रचुद् 10, कृष् 1 P; *See* **Drive. -lent,** *s.* प्रवर्तकः, प्रेरकः, प्रोत्साहकः, प्रचोदकः.

Impend, *v. i.* आ-प्र-लंब् 1 A, उपरि लंब्. 2 उत्तम् 1 P, समा-पत् 1 P, प्रत्या सद् 1 P, उप-स्था 1 U, उपागम् 1 P, निकटे-समीपे-वृत् 1 A, or स्था; 'an untimely storm i. s' उत्क्रमत्यकालदुर्दिनं (Mr. 5); 'a drought is closely i. ing' अनावृष्टिः संपद्यते लघ्वा (P. I. 7). **-ent,-ing,** *a.* उपस्थित, आसन्न, निकटवर्तिन्, उपनत, उत्तमत्.

Impenetrable, *a.* अभेद्य, अच्छेद्य, अप्रवेश्य, गहन, दुर्गम. 2 कठिन, वज्रमय (यी *f.*); 'darkness i. by the sun ' अभानुभेद्यं तमः.

Impenitent, *a.* अननुशयिन्, अननुतापिन्, खेद्य, पश्चात्ताप-हीन, अननुतप्त. **-Impenitence.** *s.* अननुतापः, अननुशयः, अखेदः; कठिनता, कठोरता.

Imperative, *a.* आज्ञापक, आदेशक, नियोजक, विधायक, प्रचोदक. 2 अविचार्य, अवश्यकर्तव्य, अनुपेक्ष्य; 'i. mood' लोट्, आज्ञार्थः. **-ly,** *adv.* अवश्यमेव.

Imperceptible, *a.* अस्पष्ट, अव्यक्त, अविभाव्य, अगोचर, अगम्य; 'i. to the senses' इंद्रियागोचर, इंद्रियातीत, अतींद्रिय; 'i. to the eye' अप्रत्यक्ष, परोक्ष, नयनागोचर; ' i. difference' अतिसूक्ष्मः भेदः. **-Imperceptibly,** *adv.* अव्यक्तं, अगोचरं, अलक्षितं, निभृतं.

Imperfect, *a.* अपूर्ण, अपरिणत, असंपन्न, अपक्व, असमाप्त, असमग्र. 2 न्यून, विकल, लुप्त, हीन, सदोष, सच्छिद्र, ऊनावयव, विकलेंद्रिय, विकलांग; 'i. memory विकला स्मृतिः; 'i. comparison ' लुप्तोपमा; 'i. tense' लङ्. **-ion,** *s.* दोषः, छिद्रं, रंध्रं, अगुणः दूषणं; कलंकः, वैकल्यं, न्यूनता, हानि *f.*, क्षति *f.*, अपर्याप्ति *f.* **-ly,** *adv.* असंपूर्ण, असम्यक्, विकलं.

Imperforate, *a.* नीरंध्र, अच्छिद्र.

Imperial, *a.* महेश्वरीय, महाराज-अधिराज-in comp.; 'i. rule' आधिराज्यं, चक्रवर्तित्वं.

Imperil, *v. t. See* **Endanger.**

Imperious, *a.* आज्ञापक. 2 दृप्त, उद्धत, धृष्ट, अवलिप्त, सावलेप; 'in an i. tone' सावलेपं, तर्जयंत्या गिरा, उद्धतं, साटोपं. **-ness,** *s.* दर्पः, अवलेपः उत्सेकः, औद्धत्यं; *See* **Pride.**

Imperishable, *a.* अनश्वर, अक्षय-य्य, अक्षयिन्, अविनाशिन्, अव्यय, अजर, अक्षर.

Impermeable, *a.* अप्रवेश्य, अभेद्य.

mpersonal, *a*. अकर्तृक, अकर्तृवाच्य; ex. by भाव 'i. verb, भाववाच्यं.

mpersonate, *v. t.* चेतनवत् उपचर् 1 P. (with loc.). **2** Feign, q. v.; 'i. ed Râma' गृहीतरामरूप: वेश:.

Impertinent, *a*. विधात, अशिष्ट, प्रगल्भ, धृष्ट, अविनीत, दुः-कु-शील. **2** अप्रस्तुत, अप्रकृत, अप्रासंगिक (की *f*.); असंगत, असंबद्ध, निष्प्रयोजन, अनर्थक. **3** पराधिकारचर्चक, अव्यापारेषु व्यापारं कुर्वत्. **-ly,** *adv*. अविनयेन, धृष्टतया, प्रगल्भं, अप्रस्तुतं. **-Impertinence,** *s*. अविनयः, प्रागल्भ्यं, धृष्टता, अशिष्टता, वैयात्यं. **2** अप्रस्तुतत्वं, असंबंधः, अनन्वयः, असंगतता.

Imperturbable, *a*. अक्षोभ्य, निर्विकार, समवृत्ति-बुद्धि; अपरिप्लव.

Impervious, *a*. दुर्भेद्य, दुष्प्रवेश्य, अभेद्य. **2** गहन, निबिड, अगम्य, संकट, संबाध, नीरंध्र.

Impetuous, *a*. तीव्र, चंड, तीक्ष्ण, उग्र, प्रबल, अविमृश्य कृत, वेगवत्, सरभस. **2** संरंभिन्, साहसिन्, अमर्षण, साहसिक (की *f*.), असमीक्ष्यकारिन्, तीक्ष्णकर्मन्. **-ly,** *adv*. वेगेन, महावेगेन, सवेगं, उग्रं, ससंरंभं, तीक्ष्णं, साहसेन, सरभसं, तरसा. **-ness, -Impetuosity,** *s*. वेगः, सं-आ-महा-वेगः; चंडता, संरंभः, तीव्रता, साहसं, अमर्षता, रभस् *n*., रभसः.

Impetus, *s*. वेगः, सं-आ-वेगः. गति-शक्ति *f*., (fig;) प्रेरणा, प्रचोदना, प्रोत्साहनं.

Impinge, *v. t.* आहन् 2 U (usually A), समापत् 1 P, संघट्ट 1 A.

Impious, *a*. अभक्त, अधार्मिक (की *f*.), अपुण्यशील, अधर्मिन्; दुष्ट, पापिष्ठ, असाधु. **-ness, -Impiety,** *s*. अभक्ति *f*., अधर्मः, पापं, दुष्कृतं, धर्मलोपः, देवनिंदा, धर्महीनता, असाधुता, दुष्टता.

Implacable, *a*. अहार्य, अचल, अशाम्य, अशमनीय, अतोषणीय, अनाराध्य, अप्रसाद्य, असांत्वनीय. **2** दीर्घ-अति-द्वेषिन्; 'i. hatred' आमरणांतिकं वैरं, दीर्घद्वेषः, बद्धवैरं.

Implant, *v. t.* नि-धा 3 U, विलिख् 6 P, निरुह् c., प्रति-नि-ष्ठा c. (ष्ठापयति), प्रतिवप् 1 P, निखन् 1 P, 'as if i. ed in the heart' प्रत्युप्तेव...अंतर्निखातेव च (Mal.5;)'so many are the thorns of anxiety i. ed in the heart' तावंतोपि विलिख्यंते हृदये शोकशंकवः (H. 4).

Implement, *s*. उपकरणं, साधनं, उपस्करः, सामग्री, द्रव्यं, पात्रं, यंत्रं.

Implicate, *v. t.* संबंध् 9 P, संश्लिष् c., लिप् 6 P, संसृज् 6 P, संक्रम् c.; 'he is i. ed in many crimes' अनेकपापैर्लिप्यते, अनेकदोषास्तस्मिन् संक्रांताः. **-ion,** *s*. संबंधः, संसर्गः, समन्वयः, अनुबंधः.

Implicit, *a*. निर्विवाद, अवैकल्पिक-असांशयिक (की *f*.); विचारानपेक्ष, अवितर्कित, अनाशंकित, अविचारित; better by 'i. ly.' **-ly,** *adv*. अवितर्कं, अनाशंकं, असंशयपूर्वं, अविचार्य, निःशंकं, निर्विवादं, निर्विकल्पं.

Implore, *v. t.* प्र-अभि-अर्थ् 10 A, याच् 1 A, सविनयं-सांजलि-याच्, अनुनी 1 P, आराध् c., प्र-सद् c. **-ingly,** *adv*. बद्धांजलि *a*., पादयोः पतित्वा, सप्रणिपातं, सविनयं.

Imply, *v. t.* सूच् 10, ध्वन् c., वच् desid. (विवक्षति), भंग्या व्यंज् c., उप-लक्ष् 10, सूच् c. **2** (As meaning) प्रति-इ c.. सुच् c., गम् c., अभि-धा 3 U; *See* **Mean;** 'these senses are i. ed' एते अर्थाः प्रतीयंते (S. B. 33); oft. by अर्थ, गर्भ in comp.; 'words i. ing censure' निंदार्थं वचः. **-ed,** *a*. विवक्षित, प्रतीत, उपलक्षित, भंग्या सूचित-ध्वनित; 'i. sense' ध्वनिः, फलितं, फलित-ध्वनित-गर्भित-अर्थः. **-ication,** *s*. विवक्षा, उपलक्षणं-णा, भंगी *f*., व्यंजना, अनुमानं.

Impolite, *a*. अशिष्ट, असभ्य, ग्राम्य, दुर्मर्याद, अप्रसुजन, दुःशील, अनार्य, अविनीत, अदक्षिण.

Impolitic, *a*. अनीतिज्ञ, नयानभिज्ञ, अबुध, अविवेचक, अविज्ञ, असमीक्ष्यकारिन्, अमतिमत्. **2** अहित, सापकार, अनर्थावह, अनिष्टकर (री *f*.), असमीक्ष्यकृत, न्यायविरुद्ध. **-ally,** *adv*. असमीक्ष्य, अनीतिज्ञवत्, अविचार्य. **-Impolicy,** *s*. दुर्णयः, अनयः, अनीति *f*.

Imponderable, Imponderous, *a*. अगुरु, लघु, निर्भार.

Import, *v. t.* (देशांतरात्) आनी or आहृ or आवह् 1 P. **2** सूच् 10, सुच् c., उद्दिश् 6 P, द्युत् c.; *See* **Imply, Mean. 3** मुख्यतया संबंध् 9 P or अवलंब् 1 A. **-s.** (I. s) विदेशीयपण्यानि, विदेशजद्रव्याणि, बहिर्देशागतवाणिज्यद्रव्याणि. **2** अर्थः, भावः, अभिप्रायः, आशयः, उद्देशः, विवक्षा; 'of like i.' तुल्यार्थं, समानार्थं. **3** गुरुत्वं, गौरवं. **-ance,** *s*. महत्त्वं, गुरुत्वं, गुरुता, गौरवं, प्रभावः, गरिमन्-महिमन् *m*. **2** उत्कर्षः, उन्नति *f*., प्रतिष्ठा, प्रतिपत्ति *f*., गौरवपदं; परम-उच्च-पदं. **3** अभिमानः, दर्पः. **-ant,** *a*. महत्, गुरु, अलघु, गुर्वर्थ, बह्वर्थ, बहु-गुरु-प्रभाव, परम; 'i. object' गुर्वर्थः. **-antly,** *adv*. गुरुतया, परमं. **-ation,** *s*. देशांतरादानयनं. **2** आनीतद्रव्याणि.

Importune, *v. t.* निर्बंधेन प्रच्छ् 6 P or प्रार्थ् 10 A or याच् 1 A. अनु-निर्-बंध् 9 P, अनुरुध् 7 U, अतिप्रार्थनया उद्विज् c. or आयस् c.; 'being i. ed &c.' निर्बंधपृष्टः स जगाद सर्वं (R. xiv. 32); पुनः पुनश्चाटुकरणमाना (Ks. 69). **-acy, -ity,** *s*. निर्बंधः, अतिनिर्बंधः, अतियाचना-प्रार्थना, नित्यप्रार्थना,

आग्रहः. -ate, a. निर्बंधशील-पर, आग्रहिन्, अतियाचक-मार्गक; 'i. demand' अतिनिर्बंधः. -ately, adv. साग्रहं, निर्बंधेन, पुनःपुनः, सनिर्बंधं.

Impose, v. t. निक्षिप् 6 P, नि-विश् c., न्यस् 4 U, नि-आ-धा 3 U, आ-समा-रुह् c. (रोपयति), स्था c. (स्थापयति), नियुज् 7 A, 10; 'i. upon' वंच् 10, विप्र-लभ् 1 A; *See* **Cheat.** -ing, a. गांभीर्यद्योतिन्, गुरुप्रभाव, विस्मयावह, अद्भुत, विस्मापक, भव्य, प्रकांड, महातेजस. -ition, s. न्यासः, आरोपः-पणं, स्थापनं, निवेशनं. 2 करः, शुल्कः-ल्कं. 3 छलं, कपटं, दंभः; *See* **Fraud.**

Impostor, s. धूर्तः, दांभिकः, वंचकः, प्रतारकः, कितवः. 2 (In religion) धर्मध्वजिन् m., लिंगवृत्तिः; *See* **Hypocrite.**

Imposture, s. वंचना-नं, छद्मन् n., दंभः, कपटं, माया, विप्रलंभः, अतिसंधानं, प्रतारणा; *See* **Fraud.**

Impossible, a. अशक्य, असाध्य, असंभव, अकरणीय, दुष्कर; gen. ex. by न शक् pass. -**Impossibility,** s. अशक्यता, असाध्यता. 2 असाध्यं, असंभवः; oft. ex. by शशविषाण-शृंगं, खपुष्पं, गगनकुसुमं.

Impost, s. करः, शुल्कः-ल्कं; बलिः, राजस्वं, राजभागः.

Imposthume, s. विद्रधिः.

Impotent, a. निर्बल, दुर्बल, अशक्त, निःसत्व; *See* **Feeble.** 2 क्लीब, पुंस्त्वहीन, नपुंसक, निष्पौरुष. 3 निष्फल, निरर्थक, व्यर्थ, वृथा-मुधा- in comp. -ly, adv. दुर्बलं, निर्वीर्यं, निःसत्वं. -**Impotency,** s. दौर्बल्यं, निःसत्वं, वीर्याभावः, क्लीबता, अपौरुषं, पुंस्त्वाभावः, वैक्लव्यं.

Impound, v. t. गोष्ठे नि-अव-रुध् 7 U or रक्ष् 1 P.

Impoverish, v. t. निर्धनीकृ 8 U, दरिद्रीकृ, धनं नश् c. or क्षि c. 2 वीर्य-शक्ति-हृ 1 P or नश् c. -ed, a. निर्धन, क्षीणधन, परिक्षीण, गतविभव, नष्टार्थ, दरिद्रीकृत, अकिंचन, गत-प्रचलित-विभव; *See* **Poor.** -ment, s. दारिद्र्यं, धननाशः-क्षयः, परिक्षीणता.

Impracticable, a. असाध्य, अशक्य, दुष्कर, असंभव, अनुपपाद्य, अकार्य.

Imprecate, v. t. शप् 1 U, आ-क्रुश् 1 P, गर्ह् 1, 10 A, अभिशंस् 1 P. -ion, s. शापः, आक्रोशः-शनं, अभिशंसनं, गालि f. -ory, a आक्रोशक, अनिष्टावेदिन्, शापगर्भ.

Impregnable, a. अजय्य, अलंघ्य, दुर्जय, दुराक्रम, अनाक्रम्य. 2 गहन, दुर्गम, अगम्य.

Impregnate v. t. सिच् 6 P, नि-आ°-, प्रक्षिप् 6 P; व्याप् 5 P or c., व्यश् 5 A, पूर् 10 2 (Make pregnant) रेतः सिच्, गर्भ ग्रह् c. or उत्पद् c., ससत्वां कृ; *See* **Pregnant.** -ed, a. सिक्त, व्याप्त, पूर्ण-गर्भ-in comp. 2 आपन्नसत्वा, गर्भवती. -ion, s. सेकः, निषेकः, गर्भाधानं.

Impress, v. t. नि-धा 3 U, न्यस् 4 U, निविश् c.; पदं ग्रह् c., निष्ठा c. (निष्ठापयति), चित्तनिष्ठ-a. कृ 8 U; संस्कृ; (हृदये) पदं कृ, स्थानं लभ् 1 A (in the mind). 2 अंक् 10, चिह्न् 10, मुद् 10: *See* below. 3 हृ 1 P, आकृष् 1 P; *See* **Attract.** -s. मुद्रा, अंकः, चिह्नं, लक्षणं. -ed, a. मुद्रित, अवगाढ, अंकित; निवेशित, निष्ठ-स्थ- in comp.; 'i. in the mind' हृदयस्थ, चित्तनिष्ठ; 'deeply i. on the ground' अवगाढा भूमौ (S. 3). -ion, s. अंकनं, चिह्नं, मुद्रा, अंकः. 2 संस्कारः, चित्तसंस्कारः. 3 अनुभवः, बुद्धि f., मति f., मतं. 4 परिणामः, उत्पन्नं, सस्कारजन्यं फलं; oft. ex. by अंतरं, अवकाशः, पदं with लभ् or ग्रह्; लब्धपदं हृदि शोकघने (R. VIII. 91), लेभेंतरं चेतसि नोपदेशः (R. VI. 66) 'made or left no i. on the heart &c.'. 5 आघातचिह्नं, छेदः. -ive, a. हृदयहारिन्, हृदयंगम, चित्ताकर्षिन्, हृदयस्पृश्.

Imprint, v. t. मुद् 10. अंक् 10, न्यस् 4 U; *See* **Impress.**

Imprison, v. t. कारायां-कारागृहे-निक्षिप् 6 P or बंध् 9 P or निरुध् 7 U. 2 बंदिग्राहं ग्रह् 9 U, आसिध् 1 P, बंदीकृ 8 U. -ment, s. कारावासः, कारानिरोधः, काराबंधनंप्रवेशः, निरोधः-धनं, बंधनं, आसेधः, प्रग्रहः, बंदीकरणं.

Improbable, a. असंभव, अघटनीय, दुर्घट, अनुपपन्न; 'it is i.' नैतदुपपद्यते, संभवति or घटते. -**Improbability,** s. असंभवः, अनुपपत्ति f., असंगति f.

Improbity, s. अशुचिता, अनृजुता, असारल्यं, कापट्यं, कौटिल्यं, शाठ्यं, जिह्मता, खलता; *See* **Fraud.**

Impromptu, a. आकस्मिक (की f.), अयत्नपूर्व, अचिंतितपूर्व. -adv पूर्वचिंतां विना.

Improper, a. अयुक्त, अनुचित, अनुपपन्न, अनर्ह; oft. by कु-अ pr.; 'i. union' असंगतिः, कुयोगः. -ly, adv. अयुक्तं, असम्यक्, अस्थाने, अनुचितं, अनुपपन्नं; 'acting i.' अकृत्यकारिन्. -**Impropriety,** s. अनौचित्यं, अन्यायः, अयुक्तता, अनुपपत्ति f. 2 (Of conduct) अविनयः, कुचरितं, अमर्यादा, दुश्चरितं, अकार्यं, अपचारः, मर्यादातिक्रमः.

Improve, v. t. उत्कृष् 1 P or c., संस्कृ 8 U, उन्नतिं-श्रेयस्त्वं-नी 1 P or प्राप् c., उप-चि 5 U, भद्रतर-श्रेयस् a. कृ; शुध् c., प्रमृज् 2 P or c., प्रतिसं-समा-धा 3 U, (as faults). -v. i. सं-वि-अभि-वृध् 1 A, उपचि pass., वृद्धिं-उन्नतिं-उत्कर्षं-इ-या 2 P or गम् 1 P or प्राप् 5 P. श्रेयस्-भद्रतर-a. भू 'has i. ed

in health ' अस्ति विशेषः; ' to i. in knowledge ' विद्यां अर्ज् 1 P or अधिगम् or आप्. -ment, s. वृद्धि f., अभि-प्र-वृद्धिः, उत्कर्षः, उन्नति f., उपचयः, उदयः, अभ्युदयः, आगमः, आधिक्यं, बृंहणं. 2 श्रेयस्त्वं, भद्रतरत्वं, वरीयस्त्वं. 3 शोधनं, प्रतिसमाधानं; ' i. in knowledge ' विद्यागमः, ज्ञानोपचयः; ' i. in health ' विशेषः.

Improvident, *a.* अदीर्घदृष्टि, अदूरदर्शिन्; *See* **Imprudent.** **-ly,** *adv.* असमीक्ष्य, अविमृश्य. **-Improvidence,** *s.* अदीर्घ-अदूर-दृष्टि *f.*

Improvise, *v. t.* अचिंतितपूर्व-प्रासक-लं-कृ 8 U or रच् 10.

Imprudent, *a.* अनयज्ञ, अनीतिमत्, अविज्ञ, अविचक्षण, अनीतिज्ञ, अनभिज्ञ, अमतिमत्; अदीर्घ-अदूर-दृष्टि. अविमृश्य-असमीक्ष्य-कारिन्, अदूरदर्शिन्, अविवेकिन्, निर्विवेक, असावधान. 2 (Of acts) अविमृश्यकृत, अनवहित; better by ' i.-ly '. **-ly,** *adv.* अविमृश्य, असमीक्ष्य, अविचार्य, अनालोचितं, अदीर्घदृष्ट्या, निर्विवेकं, अविज्ञवत्, अविवेकितया, साहसेन, सावेगं, ससंरंभं. **-Imprudence,** *s.* अदीर्घ-अदूर-दृष्टि *f.*, अपूर्वचिंता, असमीक्षा-क्षणं, अविमर्शः, अविवेकः, अविचारः. 2 अविनयः, दुर्णीति *f.*, दुर्णयः.

Impudent, *a.* धृष्ट, वियात, प्रगल्भ, निर्लज्ज, अविनीत, दुर्विनीत, निस्त्रप, लज्जा-त्रपा-व्रीडाहीन, प्रौढ, प्रतिभावत्. **-ly,** *adv.* धृष्टवत्, प्रगल्भं, निर्लज्जं, वैयात्येन, धाष्टर्येन. **-Impudence,** *s.* धृष्टता, धाष्टर्यं, वैयात्यं, प्रागल्भ्यं, अविनयः, अलज्जा, निर्लज्जता, प्रतिभा-भानं.

Impugn, *v. t.* प्रत्या-ख्या 2 P, विरुध् 7 U, निरा-कृ 8 U, अधरीकृ, प्रत्यादिश् 6 P; *See* **Contradict.** 2 अपवद् 1 A, विपरीतं वद्, निंद् 1 P, दोषं ग्रह् 9 U.

Impulse, *s.* प्रवर्तनं, प्रणोदनं, प्रवृत्ति *f.*, प्रचोदनं-ना, प्रोत्साहनं-ना; ' sudden i. ' आकस्मिकी प्रवृत्तिः, वेगः, सं-आ-वेगः. 2 हेतुः, कारणं, निमित्तं, प्रयोजनं. **-Impulsive,** *a.* प्रवर्तक, प्रणोदक, प्रोत्साहक, प्रचोदक. 2 आवेगशील, सहसाप्रवर्तिन्, वेगानुवर्तिन्, संरंभिन्; ' pray, don't grow i. ' सहसा-आकस्मिकवृत्त्या कर्मणि प्रवर्तितुं नार्हसि. **-ly,** *adv.* सहसा, आकस्मिकप्रवृत्त्या.

Impunity, *s.* दंडाभावः, दंडमुक्ति *f.* 2 अनपायः, अनपकारः, अक्षति *f.*, अहानि *f.*, अनाशः, अहिंसा, अपीडा; ' with i. (to oneself) ' अपकारं विना, स्वयमक्षतेन, आत्महानिं विना.

Impure, *a.* अशुद्ध, अशुचि, अपवित्र, अनिर्मल, समल, अमेध्य. 2 गर्ह्य, निंद्य, कश्मल, कुत्सित. 3 पांसुल, व्यभिचारिन्. **-ly,** *adv.* अपवित्रं, अशुचिवत्. **-ity, -ness,** *s.* अशुचित्वं, अमेध्यता. 2 मलः-लं, अशौचं, कालुष्यं, किट्टं, मालिन्यं, अपद्रव्यं; *See* **Dirt.** 3 गर्ह्यता, निंद्यता. 4 पांसुलता, लांपट्यं, व्यभिचारः.

Impute, *v. t.* आरुह् c., (रोपयति), संबंध् 9 P, कृप् c., प्रसंज् c., निक्षिप् 6 P; *See* **Ascribe.** 2 अप-परि-वद् 1 U, आ-अधि-क्षिप्, निंद् 1 P; *See* **Censure.** **-ation,** *s.* (Act) आरोपः-पणं, कल्पना, संबंधः, प्रसंगः; ' i. of a crime ' दोषकल्पना, दोषारोपः. 2 अभियोगः, अभिशंसनं. 3 आरोपः, आ-अधिक्षेपः, दूषणं, अपवादः, कलंकः, परि(री)-वादः; *See* **Calumny.**

In, *prep.* Gen. ex. by loc.; अंतरे, मध्ये, in comp.; with verbs by नि pr. 2 (Denoting instrument, manner, time, direction) ex. by instr.; ' i. great intimacy ' महता स्नेहेन; ' i. six days ' षड्हेन; ' i. a short time ' अचिरेण, अचिरात्; ' i. breadth ' विस्तारेण; ' drives i. a chariot ' रथेन याति-चरति; ' i. a joyful mood ' आनंदेन; ' i. order ' क्रमेण, क्रमशः; ' i. small quantities ' अल्पशः; ' i. the same manner ' तद्वत्, तथैव; ' i. as much as ' यतः, यस्मात्, यत्, oft. by abl. or instr. of abstract nouns ; *See* **Because** ; ' i. as much as it arises from ingorance ' अविद्यामूलत्वात्.

Inability, *s.* असामर्थ्यं, दौर्बल्यं, अशक्ति *f.*

Inabstinence, *s.* असंयमः, अनिग्रहः.

Inaccessible, *a.* अगम्य, दुर्गम, दुरासद, दुष्प्राप, दुरारोह, गहन, विषमस्थ.

Inaccurate, *a.* अयथार्थ, अनृत, अतथ्य, अशुद्ध. **-ly,** *adv.* अयथार्थं, अन्यथा.

Inaction, Inactivity, *s.* आलस्यं, अनुद्योगः, निर्व्यापारत्वं, कार्यद्वेषः, औदासीन्यं.

Inactive, *a.* अलस, निर्व्यापार, निरुद्यम, अव्यवसाय; *See* **Idle;** ' to be i. ' उदास् 2 A.

Inadequate, *a* अक्षम, अयोग्य, असमर्थ, अपर्याप्त, अनुचित, अननुरूप.

Inadmissible, *a.* अग्राह्य, अनुपादेय; ' i. into society ' अपांक्तेय, अपांक्त्य.

Inadvertent, *a.* अनवधान, प्रमादिन्, प्रमत्त, उपेक्षक, निरवेक्ष, असमीक्ष्य-सप्रमाद-कृत. **-ly,** *adv.* सप्रमादं, निरवेक्षं, अनवधानात्, असमीक्ष्य, असावधानं. **-Inadvertence,** *s.* प्रमादः, उपेक्षा, अनवेक्षा, अनवधानं.

Inalienable, *a.* अविच्छेद्य, अनन्यहार्य.

Inamorata,-Inamorato, *s.* *See* **Lover.**

Inane, *a.* रिक्त, शून्य, अ-निः-सार.

Inanimate, *a.* अ-वि-चेतन, प्राणहीन निर्जीव.

Inapplicable, *a.* अनुपयोज्य, अनुपपन्न, अयोग्य, अनुचित.

Inapplication, *s.* आलस्यं, अनुद्योगः, कार्यनिवृत्ति *f.*, अप्रवृत्ति *f.*, अमनोयोगः, अनभिनिवेशः.

Inapposite, Inappropriate, *a.* अयोग्य, असंगत, अप्रस्तुत, विरुद्ध.

Inappreciable, *a.* अत्यल्प, क्षुद्र.

Inapprehensive, *a.* निःशंक, अकुतोभय, वीतभय.

Inapt, *a.* अपात्र, अयोग्य. **-itude,** *s.* अपात्रता, अयोग्यता. **-ly,** *adv.* अस्थाने, असंगतं.

Inarticulate, *a.* अव्यक्त, अस्पष्ट, अस्फुट, अव्यक्तपद-वर्ण-अक्षर **-ly,** *adv.* अस्पष्टं, अव्यक्तं; गद्गदवाचा.

Inartificial, *a.* अकृत्रिम, सहज.

Inasmuch as, *adv.* यस्मात्, येन, यतः.

Inattentive, *a.* अनवधान, निरपे(वे)क्ष, अनासक्त, उपेक्षक, मंदादर, प्रमत्त, प्रमादिन्, अनवहित, अनिविष्टचित्त, शून्यहृदय. **-ly,** *adv.* सप्रमादं, अनवधानेन, प्रमादतः, असमीक्ष्य, अविमृश्य, निरपेक्षं. **-Inattention,** *s.* अनवधानं, अनपे(वे)क्षा, उपेक्षा, अनादरः, अननुरागः, अमनोयोगः, प्रमादः, शून्यहृदयत्वं.

Inaudible, *a.* अश्राव्य, कर्णागोचर; 'i. weeping' निःशब्दरोदनं.

Inaugurate, *v. t.* अभिषिच् 6 P, अधिकारे निविश् c. 2 प्रति-ष्ठा c. (प्रतिष्ठापयति), संस्कृ 8 U, उपक्रम् c., आरभ् c. (रंभयति). **-ion,** *s.* अभिषेकः, प्रतिष्ठापनं, संस्कारः: उपक्रमः.

Inaurate, *See* **Gild,-ed.**

Inauspicious, *a.* अशुभ, अमंगल, अभद्र, अकल्याण (णी *f.*). **-ly,** *adv.* अशुभं, अशुभलग्ने.

Inborn, Inbred, *a.* सहज, नैसर्गिक-स्वाभाविक (की *f.*), स्वभावज, अंतर्भव.

Incalculable, *a.* अगण्य, संख्यातीत. 2 अमित.

Incandesce, *v. t.* प्र-, ज्वल् 10, उत्-तप् c. **-ence,** *s.* अत्युष्णता, उज्ज्वलता. **-ent,** *a.* प्रज्वलन, उत्तप्त, अत्युष्ण.

Incantation, *s.* मंत्रः, अभिचारः, योगः, मंत्रप्रयोगः, माया; 'to use i.s' मंत्रैः वशीकृ 8 U or मुह् c., अभिमंत्र् 10 A, अभिचर् c.

Incapable, *a.* अक्षम, असमर्थ, अशक्त, अपर्याप्त, अनुचित, अयोग्य.

Incapacious, *a.* अपृथु, अविपुल, अविशाल, संकट, संबाध.

Incapacitate, *v. t.* शक्तिं हृ 1 P, अक्षमं-अक्षमी-कृ 8 U, अपात्री-अयोग्यं कृ.

Incapacity, *s.* असामर्थ्य, अशक्ति, *f.*, अनर्हता, अयोग्यता, अपात्रता. 2 मेधाभावः, बुद्धिहीनता.

Incarcerate,-ion, *See* **Imprison.-ment.**

Incarnadine, *v. t.* अरुणी कृ 8 U. **-a.** रक्त, रुधिरताम्र, आताम्र.

Incarnate, *a.* मूर्त, मूर्तिमत्, देहवत्, शरीरिन्, शरीरबद्ध, देहिन्, सशरीर. 2 अवतारिन्, मनुष्यरूपधारिन्, गृहीतदेह, मनुष्यरूपेण अवतीर्ण. **-ion,** *s.* अवतारः; शरीरधारणं, देहग्रहणं, मूर्तिमत्ता, सशरीरता; better by (*a.*); *See* **Embody** also.

Incase, *v. t.* भांडे नि-धा 3 U or निविश् c. 2 पि-धा, आवृ 5 U, आ-परि-वेष्ट् c., परि-आ-च्छद् 10.

Incautious, *a.* असमीक्ष्य-अविमृश्य-कारिन्, साहसिन्. 2 अनवधान, प्रमादिन्, प्रमत्त. **-Incaution,** *s.* प्रमादः, असमीक्षा; *See* **Inattention.**

Incendiary, *s.* गृह-अगार-दाहिन् *m.* **-Incendiarism,** *s.* गृहदाहः.

Incense, *s.* धूपः, तुरुष्कः, पिंडकः, सिह्लः, यावनः (olibanum); यक्षधूपः, सर्जरसः, रालः, सर्वरसः; 'artificial i.' वृकधूपः, कृत्रिमधूपकः. **-v. t.** धूप् 1 P, 10, धूपेन वास् 10. 2 उत्तिज् c., उद्दीप् c., संधुक्ष्, धुक्ष् 10, क्षुभ् c., कुप् c., प्रकुप् c.; *See* **Enrage.** **-Incensory,** *s.* धूपपात्रं-भाजनं.

Incentive, *s.* प्रलोभनं, प्रचोदनं, प्रवर्तनं, उत्तेजनं, प्रोत्साहनं; प्रेरणं, प्रणोदनं, उद्बोधकं. 2 कारणं, निमित्तं, प्रयोजनं, हेतुः. **-a.** प्रवर्तक, प्रचोदक, &c.

Inception, *s.* प्रारंभः, उपक्रमः.

Incertitude, *s.* विकल्पः, शंका, अनिर्णयः.

Incessant, *a.* सतत, अविरत, अनवरत, अविच्छिन्न, अविश्रांत, प्रसक्त. **-ly,** *adv.* अनवरतं, सततं, अजस्रं, अविच्छेदं, अश्रांतं, सर्वदा, प्रसक्तं, निरंतरं, अभीक्ष्णं.

Incest, *s.* व्यभिचारः, अगम्यगमनं; oft. by गमनं; 'i. with a mother, sister &c.' मातृगमनं; स्वसृगमनं, &c. **-uous,** *a.* अगम्यगामिन्, व्यभिचारिन्; 'i. son' मातृगामिन् *m.*

Inch, *s.* अंगुलः; 'not even an i.' न रेखामात्रमपि, नाल्पमपि; 'by i. es' अल्पाल्पं, अल्पशः.

Inchastity, *s.* व्यभिचारः; असतीत्व, पांसुलता (of women).

Inchoate, *a.* उपक्रांत, अचिरप्रारब्ध. 2 असंपूर्ण. **-ion,** *s.* उपक्रमः, प्रारंभः.

Incident, *s.* वृत्तं, वृत्तांतः, व्यतिकरः, प्रसंगः, संगति *f.*, घटना. 2 उपाख्यानं, प्रासंगिककथा. **-al,** *a.* प्रासंगिक-आनुषंगिक-आगंतुक-आकस्मिक-आपतिक-नैमित्तिक- (की *f.*), आहार्य, आगंतु, अप्रस्तुत, अप्रकृत; 'i. cause' आगंतुकारणं, कार्यनिमित्तं. **-ally,** *adv.* प्रसंगतः, प्रसंगवशात्, यदृच्छया, कथाप्रसंगेन, कार्यकारणतः, दैवात्, आगंतुकतया.

Incinerate, *v. t.* भस्मसात्कृ 8 U, भस्मीकृ.

Incipient, *a.* आरब्ध, उपक्रांत; प्रथम, अग्र, पुरोगामिन्.

Incise, *v. t.* छिद् 7 P, कृत् 6 P, तक्ष् 1, 5 P; *See* **Cut. -ion,** *s.* छेदः, कर्तनं, क्षतं, भेदः.

Incite, *v. t.* प्रवृत् c., प्रोत्सह् c., प्रेर् c., प्रक्षुभ् 10, प्रणुद् 6 P or c., उद्युज् 10; (anger &c.) उद्दीप् c., उत्तिज् c., संधुक्ष् 10. 2 आ-समा-श्वस् c. **-ation,-ment,** *s.* प्रोत्साहनं, प्रचोदनं प्रवर्तनं, प्रेरणं, उत्तेजनं. 2 **Incentive,** q. v.

Inclement, *a.* निष्ठुर, कर्कश, निर्घृण, निर्दय. 2 (Of weather) उग्र, कठोर, रूक्ष, असौम्य, तीक्ष्ण, तीव्र, प्रचंड. 3 वातवृष्टिमत्. **Inclemency,** *s.* अदया, अकारुण्यं, रूक्षता, कटुता.

Incline, *v. i.* नम् 1 P, अव-आ°-,नम्रीभू 1 P. 2 प्रवण-*a.* भू; 'favourably i. ed towards her by (her) penance' तपसा तत्प्रवणीकृतः (K. IV. 42); gen. ex. by शील in comp.; 'i. ed to favour ' अनुग्रहशील; or by इष् 6 P, वांछ् 1 P; by मनस् or काम with inf. form, or by desid. forms. **-*v. t.*** आ-अव-नम् c. (नमयति), आवृज् 10, नम्रीकृ. 2 प्रवणीकृ, प्रवृत् c., नि-उद्-युज् 10, प्रोत्सह् c., प्रेर् c.: *See* **Incite. -*s.*** उत्सर्पिणी or अवसर्पिणी भूमिः, प्रवणा भूमिः. **-ation,** *s.* प्रवृत्ति *f.*, प्रवाहः, प्रावण्यं; gen. ex. by शीलता-त्वं or आलुता-त्वं in comp. or by desid. forms; 'i. to fall ' पतनशीलता, पतयालुता, पिपतिषा. 2 भावः, अभिलाषः, इच्छा, कामः, छंदः, छंदस् *n.*,रुचि *f.*, चित्तप्रवृत्तिः; 'following one's own i. ' कामचारिन्, स्वच्छंद, स्वैरवृत्त, कामचार, स्वैर, स्वैरिन्. 3 आ-,नति *f.*; 'i. of a planet's orbit to the ecliptic' परमापमः. **-ed,** *a.* नत, आवर्जित. 2 प्रवर्तित, प्रवण, in comp., शील or आलु in comp. or by desid. forms.

Inclose, *v. t. See* **Enclose.**

Include, *v. t.* परिग्रह् 9 P, अंतर्गण् 10, समाविश् c., अंतः कल् 10, परिसमाप्-अभिव्याप्- 5 P, प्रतिसं-हृ 1 P; gen. ex. by अंतर् with भू-गम्-पत् 1 P or वृत् 1 A (with nom. of what is included). 2 आ-धा 3 U, धृ 10, आ-दा 3 A, गर्भ in comp. **-ed,** *a.* अंतर्भावित, अंतर्गणित; परिगृहीत, अंतर्भूत, अंतर्गत, अंतर्वर्तिन्, समाविष्ट, सहित, अवांतर, गर्भित, अभिव्याप्त; गर्भ in comp.; 'i. space ' अंतरालः-लं, अभ्यंतरं; 'those persons i. ' तावतान् समाकलय्य, तैर्नरैः सह. **-ing, -Inclusive,** *a.* परिग्राहिन्, अभिव्यापक; oft. by सह, or सहित *a.*; 'both days i ' उभाभ्यामपि दिनाभ्यां सह, उभयदिनसहितं; ' then enter a hermit with two others (three i. himself) ' ततः प्रविशत्यात्मनातृतीयो वैखानसः (S. 1). **-Inclusively,** *adv.* साकल्येन, अशेषेण, सहितं. **-Inclusion,** *s.* अंतर्भावः, अंतर्गणना-नं, समावेशः-शनं, परिग्रहः, अभि-,व्याप्ति *f.*, प्रतिसंहारः.

Incognito, *a.*, प्रच्छन्न, अलक्षित, प्रच्छन्न-गुप्त-रूप. **-*adv.*** प्रच्छन्नं, गुप्त-अलक्ष्य-रूपेण, निभृताकारेण.

Incognizance, *s.* अनभिज्ञानं, अप्रतिपत्ति *f.* **-Incognizant,** *a.* अनभिज्ञ, अज्ञ.

Incoherent, *a.* असंगत, असंबद्ध, अनन्वित. **-ly,** *adv.* असंगतं, अनन्वयं. **-Incoherence,** *s.* असंबंधः, असंगति *f.*, अनन्वयः, असंदर्भः.

Incombustible, *a.* अदाह्य, दुर्दाह्य.

Income, *s* आयः, उदयः, आगमः, धनागमः, अर्थप्राप्ति *f.*, धनोदयः.

Incommensurable, *a.* असमपरिमाण. असमान, असदृश. 2 अपर्याप्त.

Incommensurate, *a.* अतुल्य, असमान, अननुरूप; अपर्याप्त, न अलं, असदृश.

Incommode, *v. t.* पीड् 10, क्लिश् 9 P, आयस् c.; 'don't i. yourself ' अलमायासेन. **Incommodious,** *a.* अनुपयुक्त, अयोग्य. 2 क्लेश-पीडा-कर (री *f.*,), असुखद, उपरोधिन्.

Incommunicative, *a.* वाग्यत, मितवाच्, मितकथ, भाषणविरक्त, संलापविमुख (खी *f.*).

Incomparable, *a.* अतुल, अनुपम, अद्वितीय, निरुपम, अप्रतिम, अप्रतिरूप, अनुपमेय.

Incompassionate, *a.* निर्घृण, क्रूर, नृशंस, निर्दय; *See* **Cruel.**

Incompatible, *a. See* **Inconsistent.**

Incompetent, *a.* अशक्त, असमर्थ, अयोग्य, अकर्मक्षम, अनलंकर्मीण. **-ly,** *adv.* अयोग्यं, अक्षमवत्. **-Incompetence,-cy,** *s.* अक्षमता, असामर्थ्यं, कार्याक्षमता, अपर्याप्ति *f.*

Incomplete, *a.* अपूर्ण, असमाप्त, अनिष्पन्न. सावशेष. 2 विकल, न्यून, लुप्त, हीनांग, न्यूनावयव, लुप्तावयव, असमग्र. **-ly,** *adv.* अपूर्णं, सावशेषं, अपर्याप्तं; वैकल्येन, असमस्तं. **-ness,** *s.* अपूर्णता, असमाप्ति *f.* 2 वैकल्यं, न्यूनता.

Incomplex, Incomposite, *a.* अमिश्रित. असंकीर्ण, शुद्ध.

Incomprehensible, Inconceivable, *a* अज्ञेय, अगम्य, दुर्बोध, अचिंत्य, अविभाव्य, अग्राह्य, अबोधगम्य, अतर्क्य, अधीगम्य, ना धातीत, इंद्रियातीत, अतींद्रिय, इंद्रियागोचर.

Inconclusive, *a.* अनिर्णायक, अप्रमाण अनिश्चायक. **-ly,** *adv.* अप्रमाणं, प्रमाणं विना, अनिर्णायकत्वेन.

Incongruous, *a.* असंगत, विरुद्ध, असंबद्ध, अनुपपन्न. **-ness, -Incongruity,** *s.*

विरोधः, असंगति f., अनुपपत्ति f.; oft. by क-क्त; *See* **Congruous.**

Inconsequent, *a.* अप्रयुक्त, अप्रयोगिन्, अ-यौक्तिक, न्यायविरुद्ध, अयुक्तिसिद्ध.

Inconsiderable, *a.* अल्प, क्षुद्र, तुच्छ. 2 अल्पार्थ.

Inconsiderate, *a.* असमीक्ष्य-अविमृश्य-का-रिन्, अविवेकिन्, अविमर्शिन्, साहसिन्, प्रमत्त, असावधान; 'an i. deed' साहसं. **-ly,** *adv.* अविमृश्य, असमीक्ष्य, अविचार्य, सहसा, निर्विवेकं, सरभसं, अनालोचितं, निरवधानं, प्रमादतः, साहसेन. **-ness,** *s.* अविमर्शः, अ-विवेकः, असमीक्ष्यकारित्वं, अविचारणा, असमीक्षा.

Inconsistent, *a.* असंगत, विरुद्ध, विरो-धिन्, असंबद्ध, अनन्वित, विसंवादिन्, वि-गीत, विपरीत; परस्पर विरोधिन्-विरुद्ध, पर-स्परपराहत, संकुल, पूर्वापरविरुद्ध, क्लिष्ट; oft. ex. by विसंवद् 1 U, विरुध् pass., विप्र-वद्; *See* **Consistent** also. **-ly,** *adv.* विरोधेन, विरुद्धं, विसंवादेन, परस्परविरुद्धं.

Inconsistence,-cy, *s.* असंगति f., असंबंधः, अनन्वयः, विरोधः, वैपरीत्यं, विभेदः, अ-सादृश्यं, विसंवादः, विप्रतिपत्ति f., परस्पर-विरोधः, विरोधोक्ति f.

Inconsolable, *a.* अशरण, निर्विनोद, शो-काकुल.

Inconsonant, *a.* *See* **Inconsistent.**

Inconspicuous, *a.* अप्रकाश, अस्पष्ट. 2 अप्रधान.

Inconstant, *a.* अस्थिर, अदृढ; चल, चंचल; तरल, लोलमति, चलचित्त. **-Inconstancy,** *s.* अस्थैर्यं, तरलता, चंचलत्वं; *See* **Fickle, -ness.**

Incontaminate, *a.* अकलंक, अदूषित, पवित्र.

Incontestable, *a.* निर्विवाद, अविचार्य, अप्रत्याख्येय, निःसंदेह, सुनिश्चित.

Incontinent, *a.* असंयत, अवशिन्, अजितें-द्रिय, व्यभिचारिन्. **-Incontinence,** *s.* असंयमः, अदमः, अयमः, अजितेंद्रियत्वं, व्य-भिचारः, लांपट्यं, इंद्रियावृत्तः.

Incontrovertible, *a.* अप्रत्याख्येय, निर्वि-वाद, अबाध्य, असंदिग्ध.

Inconvenient *a.* अनुपयुक्त, अनुचित, अ-पर्याप्त, अयोग्य; अहित, असुखकर, क्लेशकर (री f.); क्लेशद, दुःखावह, उपरोधक, दुःखद. **-Inconvenience,** *s.* अयोग्यता, अनौचित्यं, अनुपयोगः, अ-पर्याप्ति f. 2 क्लेशः, असुखं, उपरोधः, पीडा, आयासः, आयास or क्लेश-हेतु. or कारणं. **-v. t.** उप-रुध् 7 U, बाध् 1 A, पीड् 10; *See* **Convenience.**

Inconversant, *a.* अनभिज्ञ, अविज्ञ; अनभ्यस्त.

Incorporate, *v. t.* संमिश्र् 10, संहन् 2 P, संयुज् 7 U, 10, संसृज् 6 P. संश्लिष् c., ए-कीकृ 8 U. **-v. i.** एकीभू, संसृज्-संयुज्- pass. **-ion,** *s.* संयोगः, संश्लेषः, संमिश्रणं, संसर्गः.

Incorporeal, *a.* अशरीरिन्, विदेह, निरवयव.

Incorrect, *a.* अशुद्ध, अशुचि, सदोष, दोष-वत्. 2 असत्य, अयथार्थ, वितथ; 'i. in conduct' दुर्वृत्त, दुराचार. **-ly,** *adv.* मिथ्या, अन्यथा, असत्यं, अयथार्थं; अशुद्धं. **-ness,** *s.* अशौचं, अशुद्धता, असत्यता, &c.

Incorrigible, *a.* अशोध्य, असमाधेय, शि-क्षातीत, असाध्य, अप्रतिसमाधेय.

Incorrodible, *a.* अक्षयणीय.

Incorrosive, *a.* अविलयन, अनाशक.

Incorrupt, *a.* अदुष्ट, शुचि, पवित्र, शुद्ध. **-ness,** *s* शुचिता, शुद्धता.

Incorruptible, *a.* अनाश्य, अदूष्य, अक्षय.

Increase, *v. i.* वृध् 1 A, वि-सं-प्र-परि°, एध् 1 A, सं-ऋध् 4,5 P, स्फाय् 1 A, आ-प्यै 1 A, वृद्धिं या-इ 2 P or गम् 1 P or प्राप् 5 P, प्र-उप-चि pass., मुर्छ् 1 P, (मुमूर्छ सहजं तेजो हविषेव हविर्भुजां R. x. 79), प्ररुह् 1 P. 2 विस्तॄ-वितन्- pass., वि-प्र-सृ 1 P. **-v. t.** वृध् c., एध् c., ऋध् c., आप्यै c., स्फाय् c. (स्फावयति), आगम् c., बृंह् c. वृद्धिं नी 1 P, प्ररुह् c., प्र-उप-चि 5 U. 2 विस्तॄ c., वितन् 8 U, प्रसृ c., **-s.** वृद्धि-स्फीति-समृद्धि f., उप-प्र-चयः, वर्धनं, आप्यायनं, बृंहणं, उ-न्नति f., विस्तारः, आधिक्यं. **-ing,** *a.* व-र्धिष्णु, प्रचीयमान, प्ररोहिन्. *See* **Grow.**

Incredible, *a.* अश्रद्धेय, अविश्वास्य, प्रत्य-यातीत, विश्वासानर्ह, अतिप्रत्यय-विश्वास, अप्रमाणभूत.

Incredulous, *a.* अश्रद्धालु, अप्रत्ययिन्, शं-काशील, अविश्वासशील. **-ly,** *adv.* साशंकं, अप्रत्ययेन. **-Incredulity,** *s.* अप्रत्ययः, अ-श्रद्धा, अविश्वासः.

Incremate, *v. t.* दह् 1 P.

Increment, *See* **Increase** (*s.*).

Incriminate, *v. t.* अभियुज् 7 A, 10; *See* **Accuse.**

Incrust, *v.* *See* **Encrust.**

Incubate, *v. i.* अत्र-स्था 1 A, अंडानामुपरि संविश् 6 P, अंडानि पुष् 1, 9 P. **-ion,** *s.* अंडपोषणं.

Incubus, *s.* कुस्वप्नः, दुःस्वप्नः.

Inculcate, *v. t.* अनु-,शास् 2 P, उपदिश् 6 P, (चित्ते) निविश् c., शिक्ष् c.; *See* **Impress.**

Inculpate, *v. t.* *See* **Censure.**

Incumbent, *a* अवलंबिन्; आश्रित, उपरिस्थ. 2 आवश्यक; oft. ex. by pot. pass. part. or अर्ह् 1 P. **-s.** अधिकृतः, नियोज्यः, वृत्तिभुज् *m.*, वृत्तिभोगिन्-धारिन् *m.*

Incur, *v. t.* भज् 1 U, आश्रि 1 U, आप् 5 P, लभ् 1 A, आवह् 1 P, उत्पद् c.; gen. ex. by इ-या- 2 P, गम् 1 P &c. with object, by pot. pass. part., अर्ह् 1 P or अर्ह, योग्य,

भाजनं, पात्रं, in comp.; 'be i. s blame' वाच्यतां याति, दोषभाजनं-दोषभाक्-दोषपात्रं भवति; 'i. s debt' ऋणं करोति, 'you will only i. sin' पापमेवाश्रयेथाः; 'i. s a penalty' दंडयो भवति, दंडमर्हति.

Incurable, *a.* असाध्य, अशमनीय, दुरुपचार, अप्रतिकार्य, अपरिहार्य, असमाधेय, निरुपाय.

Incurious, *a.* अनुत्सुक, अजिज्ञासु, अकुतूहलिन्.

Incursion, *s.* अवस्कंदः-दनं, अभिद्रवः, उपप्लवः, आक्रमः, अभियायाणं, अभिग्रहः; 'to make i. s' अवस्कंद् 1 P, अभिद्रु 1 P; *See* **Attack.** **-Incursive,** *a.* उपप्लाविन्, उपद्राविन्.

Incurvate, *v. t.* नम् c., आवृज् 10, भुज् 6 P, आकुंच् c. **-ion,** *s.* आ-,नतिf.,आकुंचनं.

Indebted, *a.* ऋणिन्, ऋणग्रस्त-बद्ध. **2** उपकृत, अनुगृहीत, कृतोपकार; 'I am i. to fortune' दैवेनानुगृहीतोस्मि

Indecent, *a.* ग्राम्य, अश्लील, अवाच्य, अश्राव्य. **2** अविनीत, विनयशून्य-रहित, निर्मर्याद, अतिक्रांतमर्याद, विनय; अशिष्ट, असभ्य, शिष्टाचारविरुद्ध. **3** अयुक्त, अन्याय्य, लज्जाकर (री f.), निंद्य, निर्लज्ज. **-ly,** *adv.* गर्हितं, अश्लीलतया, अविनयेन, अमर्यादं, अयुक्तं. **-Indecency,** *s.* अश्लीलता, ग्राम्यता. **2** अविनयः, अमर्यादा, अशिष्टता, मर्यादातिक्रमः. **3** अयुक्त , अनुपपत्ति f., निंद्यता, गर्ह्यता, अन्यायः, कुरीति f. अनीति f., अनयः, कुशीलं, अपचारः

Indecision, *s.* संदेहः, अनिर्णयः, अनिर्धारणं, विकल्पः, संशयः, अनिश्चयः, वितर्कः, आशंका, द्वापरः. **2** विकल्प-वितर्क-शीलता, संदिग्ध अस्थिर-मतित्वं, चलचित्तता, लौल्यं, चंचलता.

Indecisive, *a.* संदिग्ध, अनिर्णीत, अनिश्चित, सविकल्प, अनिर्णायक. **2** विकल्प-वितर्क-संदेह-शील, अस्थिर-संदिग्ध-लोल-मति,-धी,-बुद्धि,-चित्त, अनवस्थित, चलचित्त, दोलायमानचित्त; *See* **Fickle.** **-ly,** *adv.* अनिश्चितं, ससंदेहं.

Indeclinable, *a.* अव्यय, अविकार्य, अविभक्तिक; 'an i. word' अव्ययः-यं, निपातः.

Indecorous, Indecorum, *See* **Indecent, Indecency.**

Indeed, *adv.* नूनं, खलु, किल, नाम, वस्तुतः, परमार्थतः, सत्यं, तत्त्वतः, अर्थतः, ध्रुवं, तावत्, हि, एव.

Indefatigable, *a.* अक्लांत, अश्रांत, अविषण्ण, महोत्साह, बहुश्रमक्षम, अनिर्विण्ण; *See* **Assiduous.**

Indefeasible, *a.* अलोपनीय, अविनाश्य.

Indefensible, *a.* अरक्षणीय, अप्रतिपादनीय. अनुत्तर.

Indefinable, *a.* अनिर्वाच्य, अनिर्वचनीय, अवर्णनीय, परिच्छेदातीत. Gen. ex. by किम् *pron.* with अपि; (विकारः कोप्यंतर्जडयति Mal. I).

Indefinite, *a.* अनियत, अनिश्चित, अनिर्दिष्ट, अलक्षित.

Indelible, *a.* अक्षर, शाश्वत (ती f.), अनाश्य, अलोप्य, अक्षय्य, अमार्ज्य.

Indelicate, *a.* ग्राम्य, अश्लील. **2** अविनीत, अशिष्ट, असभ्य, अयुक्त; *See* **Indecent.**

Indemnify, *v. t.* (क्षतिं) पूर् 10, निष्कृ 8 U, निस्तॄ c., अपाकृ, प्रतिकृ, शुध् c., प्रसृज् 2 P or c, क्षेमं प्रतिवि-धा 3 U. **-Indemnity,** *s.* क्षति-हानि-पूरणं, क्षतिनिष्कृति f. -निस्तारः, अपकारशुद्धि f., प्रतिफलं, क्षेमप्रतिविधानं, योगक्षेमः; 'a paper granting i.' अभयपत्रं, दंडाभयपत्रं.

Indent, *v. t.* दंतुरीकृ 8 U, भंगुरीकृ; अनुक्रकचं छिद् 7 P or अंक् 10. **-ation,** *s.* भंगः, छेदः, भंगुरीकरणं. **-ed,** *a.* दंतुर, दंतुरित, भंगुर, सभंग, अनुक्रकच. **-ure** *s.* प्रतिज्ञानियम-पत्रं.

Independent, *a.* स्वाधीन, अनायत्त, स्वायत्त, स्वतंत्र, आत्मायत्त, आत्मतंत्र, अनाश्रित, अपरायत्त, अ-वि-वश, अपरतंत्र. **2** स्वैरिन्, स्वच्छंद, स्वैरवृत्ति, स्वैर, स्वैर-काम-चारिन्, यादृच्छिक (की f.), निर्यंत्रण, अनियंत्रण, स्वेच्छाचारिन्; *See* **Free;** 'i. of' विमुच्य, विहाय, विना; *See* **Except;** निरपेक्ष, अनपेक्ष, in comp., बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवति (S. B. 508) 'i. of external causes' &c. **-ly,** *adv.* स्वातंत्र्येण, स्वैरं, स्वेच्छया, स्वच्छंदं, अनायत्तं, यदृच्छया, यथेष्टं, यथाकामं, स्वतंत्रं, अन्यनिरपेक्षं. **-Independence,** *s.* स्वातंत्र्यं, आत्माधीनता, अपरवशता, अपारतंत्र्यं, स्वाच्छंद्यं, स्वैरता, यदृच्छा.

Indescribable, *a.* अकथ्य, अतिकथ, वाग्विभवातिवृत्त, वर्णनातीत, वर्णनाविषय, अवर्णनीय, अनिर्वाच्य; oft. by कः-का-किं with अपि; काप्यभिख्या तयोरासीत् (R. I. 46) 'an i. splendour' &c.; 'the splendour of that pair is simply i.' किं कथ्यते श्रीरुभयस्य तस्य (K. vii. 78).

Indestructible, *a.* अक्षय्य, अनश्वर, अनाश्य, अविनाशिन्, अजर, अक्षयिन्.

Indeterminable, *a.* अलक्ष्य, अपरिमेय; संदिग्ध.

Indeterminate, *a.* अनियत, अनिर्दिष्ट, अनिर्णीत, संदिग्ध, सविकल्प, अलक्षित; अपरिमित. **-ion,** *s.* **Indicision,** q. v.

Index, *s.* सूचि(ची)पत्रं, सूचि-ची f., निघंटुः, अनुक्रमणिका. **2** प्रदेशि(शि)नी, दर्शकः. **3** (Indicative of) ex. by ज्ञापक-सूचक-गमक. **-a.,** तदेव गमकं पाण्डित्यवैदग्ध्ययोः (Mal. I) 'that only is the i. of wisdom and skill'; *See* **Indicate.**

India, *s.* भारत, भ(भा)रतवर्ष, जंबुद्वीपः. **-Indian,** *a.* भारतीय, भारतदेशीय.

Indicate, *v. t.* सूच् 10, धुत् c., वि-अंज् 7 P or c. गम् c., (गमयति), प्र-निर्-दिश् 6 P, प्र-दृश् c., बुध् c., प्रकटीकृ 8 U, आविष्कृ, निरूप् 10, प्रकाश् c., ज्ञा c., (ज्ञापयति), नि-आ-विद् c., लक्ष् 10, निर्वच् 2 P, or c., अभि-धा 3 U, अवगम् c., प्रति-इ c. (प्रत्याययति), पिशुनयति (D.). **-ion,** *s.* लक्षणं, चिह्नं, लिंगं, व्यंजनं, सूचना, रूपं, अभिज्ञानं, आकूतं, आकारः, इंगितं. **2** (Act) प्रकाशनं, निर्देशः, प्रदर्शनं. **-ive, -ory,** *a.* दर्शक, गमक, सूचक, व्यंजक, द्योतक, वाचक, ज्ञापक, निर्देशक, बोधक, पिशुन; 'i. of equal love' तुल्यानुरागपिशुनं (V. 2); 'i. mood' स्वार्थः.

Indict, *v. t.* अभियुज् 7 A, 10, अपवद् 1 A. **-ment,** *s.* अभियोगः, अभिशंसनं, अभियोगपत्रं.

Indifferent, *a.* सामान्य, मध्यम, विगुण. **2** समभाव, समबुद्धि, समदृष्टि, समदर्शिन्, समपक्ष, तटस्थ, अपक्षपातिन्, निःसंग, मुक्तसंग. **3** निरपेक्ष, अनपेक्ष, निरादर, अनभिलाष, निरभिलाष, निरीह, निःस्पृह, विरक्त, निरुत्सुक, अव्यग्र; 'to remain or be i.' उदास् 2 A or उपेक्ष् 1 A, किमित्युदासते भरताः (Mal. 1.); (in good sense) माध्यस्थ्यं अवलंब् 1 A, माध्यस्थ्यमिष्टेऽप्यवलंबतेर्थे (K. i. 52). **-ly,** *adv.* निरपेक्षं, निरुत्सुकं, निरभिलाषं. **2** मध्यमतया, सामान्यतः. **-Indifference,** *s.* औदासीन्यं, माध्यस्थ्यं, विरक्ति *f.*, वैराग्यं, अनभिलाषः, अनपेक्षा, अनीहा, अस्पृहा, निःस्पृहता, निरीहता, निःसंगता, ताटस्थ्यं. **2** प्रमादः, उपेक्षा, अमनोयोगः, अनवेक्षा, अनवधानं, अनादरः. **3** समभावः, अपक्षपातः, असंगः.

Indigent, *a.* दीन, दरिद्र, अधन, दुर्गत, निःस्व, अकिंचन; *See* **Poor. -ly,** *adv.* दीनवत्, सकार्पण्यं, सदैन्यं. **-Indigence,** *s.* दैन्यं, दारिद्र्यं, निर्धनता, दुर्गति *f.*, दुःस्थिति *f.*, निःस्वता, अकिंचनत्वं.

Indigenous, *a.* स्वदेशोद्भव, स्वदेशीय, स्वदेशजात.

Indigestion, *s.* अजीर्णं, अपाकः, अग्निमांद्यं, मंदाग्निः, अन्नविकारः, अन्नापरिपाकः. **Indigestible,** *a.* दुष्पच, दुर्जर, अजर्य.

Indignant, *a.* कोपाकुल, इद्धमन्यु, समन्यु, सरोष, संरंभिन्, कुपित, अतिक्रुद्ध, अतिरुष्ट, जातामर्ष, संजातकोप, दीप्तकोप. **-ly,** *adv.* सरोषं, सकोपं, सामर्षं, सक्रोधं. **-Indignation,** *s.* मन्युः, संरंभः, कोपः, रोषः, क्रोधः, अमर्षः, रुष् *f.*, प्रतिघः, क्रुध् *f.*, गुरुकोपः.

Indignity, *s.* अप(व)मानः, परिभवः, अवज्ञा, अनादरः, उपेक्षा, अवधीरणं-णा, तिरस्कारः, धिक्कारः, *See* **Disgrace, Insult,** also.

Indigo, *s.* नीलं; (plant) नीली, काला, क्लीतकिका, ग्रामीणा, मधुपर्णिका, रंजनी, श्रीफली, तुत्था, द्रोणी, दोला, नीलिनी, मेला, तूणी.

Indirect, *a.* अनृजु, वक्र, कुटिल, जिह्म, परोक्ष; 'i. tax'; परोक्षकरः; 'i. hint' वक्रोक्ति *f.*, भंगिभाषणं, वक्रभणितं, भंग्युक्तिः, भंगि-गी *f.* **-ly,** *adv.* भंग्युक्त्या, वक्रोक्त्या. **2** वक्रं, कुटिलं, अनृजु, असरलं, तिर्यक्, तिरस्.

Indiscernible, *a.* अप्रत्यक्ष, अव्यक्त, अदृष्टिगोचर.

Indiscreet, *a.* अविमृश्य-असमीक्ष्य-कारिन्, अविचक्षण, अदूरदर्शिन्, अविवेचक, अनीतिज्ञ, अमतिमत्, विवेकहीन-शून्य, अनवहित **-ly,** *adv.* अविमृश्य, असमीक्ष्य, अविचार्य, निर्विवेकं, अविचार-असमीक्षा- पूर्वं. **-Indiscretion,** *s.* अविवेकः, अविचारः-रणा, असमीक्षा; अविज्ञता, अविमर्शः, असमीक्ष्यकारिता-त्वं; अनवधानं, प्रमादः, अनपेक्षा.

Indiscriminate, *a.* अविविक्त, निर्विशेष, अपरिच्छिन्न, अपृथक्कृत. **2** संकुल, संकीर्ण, अव्यवस्थित. **-ing,-ive,** *a.* अविवेकिन्, अविशेषज्ञ, निर्विवेक. **-ion,** *s.* अविवेकः, अविचारः-रणा. अपरिच्छेदः, अविज्ञानं. **-ly,** *adv.* अविविक्तं, निर्विशेषं. **2** संकुलं. संकीर्णं, अक्रमेण, क्रमं विना.

Indispensable, *a.* अवश्य, अपरित्याज्य, अपरिहार्य, अवश्यकार्य; 'an i. duty' नित्यकर्मन् *n.*

Indispose, *v. t.* विरंज् c., विमुखीकृ 8 U, अरुचि-विरक्ति-उत्पद् c. or जन् c, प्रतिकूल-*a.* कृ; न प्रवृत् c. **2** अस्वास्थ्यं जन् c. **-ed,** *a.* विरक्त, विमुख-पराङ्मुख (खी *f.*), अनिच्छु, अननुकूल, द्वेषिन्, प्रतिकूल, अप्रवृत्त, अनभिलाषिन्. **2** अस्व(सु)स्थ, अस्व(सु)स्थशरीर; 'severely i.' बलवदस्वस्थशरीर. **-ition,** *s.* विरक्ति *f.*, विरागः, अरुचि *f.*, विमुखता, अनिच्छा, अनीहा, अप्रवृत्ति *f.*, अस्पृहा, प्रतिकूलता. **2** अस्वास्थ्यं, असुस्थता, शरीरास्वास्थ्यं.

Indisputable, *a.* *See* **Incontestable.**

Indissoluble, *a.* अभेद्य, दुर्भेद्य, अलंघ्य; सुदृढ, दृढबद्ध, सुसंहत. **2** अद्राव्य, अक्षरणीय.

Indistinct, *a.* अव्यक्त, अस्फुट, अस्पष्ट, अप्रकाश, अप्रत्यक्ष. **2** संकुल, संकीर्ण; 'an i. speech.' क्लिष्टं, अविस्पष्टं. **-ly,** *adv.* अव्यक्तं. अस्पष्टं. **-ness,** *s.* अव्यक्ति *f.*, अस्पष्टता.

Indistinguishable, *a.* अपरिच्छेद्य, अविज्ञेय, अलक्ष्य.

Indite, *v. t.* लिख् 6 P.

Individual, *s.* व्यक्ति *f.*, पुरुषः, एकजनः, अवयवः. **-a.** व्यक्तिमत्, अव्यापक, अव्यापिन्, एक. **-ity,** *s.* व्यक्तिता, अव्यापकत्वं, व्यक्तिः 2 पृथक्त्वं, पार्थक्यं, ममता. **-ly,** *adv.* एकैकशः, प्रत्येकशः, एकैकं, प्रत्यवयवं, अवयवशः, पृथक्, पृथक्.

Indivisible, *a.* अविभाज्य, अभेद्य, अनंश्य, निरवयव.

Indocile, *a.* अविनेय, अवश्य, अविधेय, अवशग, दुर्दम, दुर्दांत, अनधीन, अनायत्त, स्वैरिन्, स्वच्छंद.

Indoctrinate, *v. t. See* **Advise.**

Indolent, *a.* तंद्रिल, अलस, तंद्रालु, मंद, निरुद्यम, उद्योगविरक्त, कार्यद्वेषिन्, कार्यविमुख (खी *f.*), निश्चेष्ट, निरुत्साह, जड, मंदक्रिय. **-ly,** *adv.* निरुद्यमं, अलसवत्, मंदतया. **-Indolence,** *s.* तंद्रा, आलस्यं, तंद्रि-द्री *f.*, मंदता, जाड्यं, अनुद्योगः, कार्यविमुखता, अनुत्साहः, कार्यद्वेषः.

Indomitable, *a.* दुर्दम, दुर्दांत, अदम्य, अजय्य. 2 अदीन-अकृपण-चेतस्, अत्युत्साहवत्, उच्चसत्व.

Indoors, *See* under **Door.**

Indubitable, *a.* असंदिग्ध, सुनिश्चित, अनाशंक्य, निःसंशय; *See* **Certain.**

Induce, *v. t.* अनु-नी 1 P, प्रवृत् c., उद्-नि-युज् 10, प्रचुद् 10, प्रोत्सह् c., प्रेर् c.; *See* **Incite.** 2 आ-कृष् 1 P, प्र-वि-लुभ् c., हृ 1 P; oft. ex. by causal forms. 3 उत्पद् c., जन् c. (जनयति), सं-उद्-भू c., आवह् 1 P. 4 प्रबुध् c. **-ment,** *s.* प्रोत्साहनं, प्रवर्तनं, अनुनयः; प्रचोदनं. 2 कारणं, हेतुः, निमित्तं, प्रलोभनं; *See* **Incentive.** **-Induction,** *s.* अनुमानं; अपवाहः. **-Inductive,** *a.* आनुमानिक (की *f.*).

Induct, *v. t.* धर्माधिकारे नियुज् 7 A, 10. **-ion,** *s.* प्रतिष्ठापनं.

Indulge, *v. i.* आ-सञ्ज् pass, आसक्त-निरत-*a.* भू 1 P (with loc.); सेव् 1 A, भज् 1 U. **-v. t.** उप-,लल् 10, उपच्छंद् 10; अनुग्रह् 9 U, तृप् c., तुष् c.; अनु-वृत् 1 A, अनुरुध् 4 A, अनुवि-धा 3 U, अनुप्रविश् 6 P, पूर् 10. 2 अनु-ज्ञा 9 P, अनु-मुद् 1 A, अनु-मन् 4 A, क्षम् 1 A, 4 P, उपेक्ष् 1 A, न विरुध् 7 U, न संयम् 1 P; न निग्रह् 9 U, न निषिध् 1 P. **-ence,** *s.* आसक्ति *f.*, निरति *f.*, सेवा, आसंगः; शीलता-आलुता-in comp. 2 अक्रमः, अनिषेधः, असंयमः, अनिग्रहः, अप्रतिरोधः. 3 तोषणं, तर्पणं, अनुवर्तनं, लालनं, उपच्छंदनं, अनुरोधः, अनुविधानं, अनुवृत्ति *f.*, अनुवृत्तं, छंदोनुवृत्तं. 4 प्रसादः, अनुग्रहः; अनुज्ञा, अनुमति *f.* **-ent,** *a.* सदय, अनुग्रहशील, अनुग्राहिन्, अनुकूल, अनुकंपक, करुणात्मक. 2 छंदोनुवर्तिन्, छंदानुरोधिन्, अनुविधायिन्. **-ently,** *adv.* सानुरोधं, छंदोनुरोधेन, सदयं, सानुग्रहं, सकारुण्यं.

Indurate, *v. t.* घनीकृ 8 U, दृढीकृ, संहन् 2 P. **-v. i.** घनीभू. **-ion,** *s.* घनीकरणं, काठिन्यं, घनीभावः, घनता.

Industry, *s.* उद्यमः, उद्योगः, व्यवसायः, अध्यवसायः, उत्साहः, यत्नः, अभियोगः, चेष्टा, क्रिया, कार्याभिनिवेशः, कर्मशीलता, कार्यप्रसक्ति-प्रवृत्ति *f.*, अभ्यासः, अनालस्यं, परिश्रमः, आ-प्र-यासः, सोद्योगता. **-ious,** *a.* उद्यमिन्, उद्योगिन्, व्यवसायिन्, सोद्यम, सोद्योग, सोत्साह, अनलस, कार्यासक्त, कर्मशील, कर्मनिष्ठ, कर्मासक्त, कर्मशूर, क्रियापरायण, अतंद्रित, उद्युक्त, उद्यत, कर्मप्रसित. **-iously,** *adv.* सोद्यमं, सोद्योगं, सोत्साहं, सप्रयत्न, प्रसक्तं, अभिनिवेशेन.

Inebriate, *v. t.* मद् c., मदं उत्पद् c. **-ed,** *a.* मत्त. क्षीब, मदोन्मत्त, उन्मद. **-ion,** *s.* मदः, मादः, उन्मादः, क्षीबता.

Ineffable, *a. See* **Indescribable.**

Ineffaceable, *a.* अनपमृज्य, अलोपनीय.

Ineffective, Ineffectual, *a.* निष्फल, विफल, व्यर्थ, मोघ, निरर्थक, निष्प्रयोजन. 2 निर्बल, असमर्थ, अक्षम, असिद्धिकर (री *f.*), निष्प्रभाव, अवीर्यवत्, *See* **Fruitless.** **-ly,** *adv.* निष्फलं, व्यर्थं, मुधा, वृथा, निरर्थकं; निर्बलं. **-Inefficacy,** *s.* अप्रभावः, अक्षमता, अशक्ति *f.*, असामर्थ्यं, शक्तिहीनता, वैफल्यं, मोघत्वं, व्यर्थता, अनर्थकत्वं. **-Inefficacious,** *a.* अप्रभाव, अक्षम, असमर्थ, तेजोहीन, अप्रबल. 2 मोघ, व्यर्थ, अकिंचित्कर (री *f.*), विफल, निष्फल. **-Inefficient,** *a.* अनुपयुक्त, कार्याक्षम, अनलंकर्मीण, अयोग्य, अकार्यसाधक. 2 अप्रबल.

Inelastic, *a.* स्थितिस्थापकत्वहीन.

Inelegant, *a.* अशोभन, अश्लील, अप्रशस्त, अविनीत; *See* **Indecent.** **-Inelegance,** *s.* अलावण्यं; अशोभा, &c.

Ineligible, *a.* अवरणीय, अयोग्य, अयुक्त.

Ineloquent, *a.* वागपटु; अवाग्मिन्.

Inept, *a.* अयोग्य, अनुचित, अनर्ह. 2 मूढ, मूर्ख, बालिश.

Inequality, *s.* वैषम्यं, असाम्यं, विषमता, विभेदः, असादृश्यं, भिन्नता.

Inequitable, *a.* अन्याय्य, अधर्म्य, न्यायविरुद्ध.

Ineradicable, *a.* अनुन्मूल्य, अविनाश्य.

Inert, *a.* जड, निश्चेष्ट, अचेष्ट, अचल, गतिहीन, निश्चल, अचेतन. 2 अनुद्योगिन्, मंद, तंद्रिल, जड, अलस. **-ly,** *adv.* मंदं, जडवत्. **-ness,** *s.* जाड्यं, अचेष्टा, अनुद्योगः, मंदता, आलस्यं, कार्यविमुखता. **-Inertia,** *s.* निश्चलता, जाड्यं

Inestimable, *a.* अनर्घ-र्घ्य, अमूल्य, अत्युत्कृष्ट.

Inevitable, *a.* अपरिहार्य, अवश्यभाविन्, अहार्य, अवारणीय, अनिवार्य, नियत, भवितव्य, अवश्यक, आनुषंगिक (की *f.*). **-y,** *adv.* अवश्यं, नियतं, ध्रुवं, एकांत in comp., (एकांतविध्वंसिषु पिंडेषु R. ii. 57.)

Inexcusable, *a.* अक्षम्य, असोढव्य, अमर्षणीय. 2 निरुत्तर. अनिवार्यदोष, निर्व्यपदेश.

Inexhaustible, *a.* अक्षय, अक्षयिन्, अविनाश्य, अविध्वंसिन्, अनंत, अव्यय.

Inexorable, *a.* निष्ठुर, निरनुरोध, अनाराध्य, अनम्य, अननुनेय. निरनुक्रोश, निर्दय, काठिणपाषाण-हृदय, कठोरचित्त.

Inexpedient, *a.* अनुचित, अयोग्य, अनर्ह, अनुपपन्न.

Inexperience, *s.* अननुभवः, अपक्वबुद्धित्वं, अपरिणतमतित्वं, व्यवहारानभिज्ञता, अबहुदर्शित्वं. **-ed,** *a.* अपक्वबुद्धि, अपरिणतप्रज्ञ, अनभिज्ञ, व्यवहारानभिज्ञ अल्पदृश्वन्, अबहुदर्शिन्.

Inexpert, *a.* अकुशल, अनिपुण, अविदग्ध, अपटु, अदक्ष.

Inexpiable, *a.* अशोध्य, प्रायश्चित्ताक्षम, अनिष्करणीय.

Inexplicable, *a.* अव्याख्येय, अगम्यार्थ, दुर्बोध, गहन, अबोध्य, दुर्गम.

Inexpressible, *a.* अनभ्युद्य, अकथ्य; *See* **Indescribable.**

Inextinguishable, *a.* अशाम्य, अनिर्वाप्य.

Inextricable, *a.* दुस्तर, अनुद्धार्य.

Infallible, *a.* अमोघ, अव्यर्थ, निश्चित. 2 अप्रमादाधीन, प्रमादाक्षम, अस्खलनशील, अस्खलित-मति-बुद्धि, भ्रमानर्ह. **-Infallibility,** *s.* अभ्रांति *f.*, प्रमादाक्षमता, अप्रमादित्वं.

Infamy, *s.* अ अप-यशस् *n.*, दुष्कीर्ति *f.*, अकीर्तिः, अप्रतिष्ठा, वाच्यता, कलंकः, अपकर्षः. **-ous,** *a.* अयशस्कर (री *f.*), निंद्य, वाच्य, कलंकावह, गर्ह्य, अतिदुष्ट, गर्हणीय. 4 (Of persons) दुष्कीर्तिमत्, अयशस्विन्, अपयशस्क, ख्यातगर्हण, अभिशस्त. **-ousness,** *See* (*s.*).

Infant, *s.* बालः, शिशुः, बालकः, स्तनंधयः, स्तनपः-पाः, अर्भकः, दारकः, डिंभः, क्षीरपाः, स्तन-क्षीर-पायिन् *m.*, उत्तानशयः;(all *f* also).**-a.,-ile,-ine,** *a.* बाल-योग्य, बालकीय, (*s.*) in comp. 2 व्यवहारायोग्य, अप्राप्तव्यवहारदश; 'i. state.' बालावस्था. **-Infancy,** *s.* बाल्यं, शैशवं, शिशु-बाल-भावः, बाल्यावस्था, शिशु-बाल-कालः. 2 प्रथम-बाल-अवस्था, आरंभः, प्रारंभः. **-Infanticide,** *s.* बालहत्या, शिशुवधः- हत्या. 2 बालहन् *m.*, बालघातकः.

Infantry, *s.* पत्तयः, पदातयः, पदातिकाः (*pl.*), पदातिबलं, पादातं, पत्तिसैन्यं.

Infatuate, *v. t.* मुह् c., मद् c., बुद्धि-ज्ञानं हृ 2 P or लुप् c. **-ed,** *a.* मूढ, वि-सं-परि-मूढ, विमोहित, हत or नष्ट-बुद्धि or ज्ञान, नष्टलुप्त-संज्ञ, बुद्धिभ्रष्ट, मोहोपहत, उन्मत्त; 'i. b.) lust,' कामांध, काममूढ. **-ing,** *a.* मोहिन्, मोहकारिन्, मोहन. **-ion,** *s.* मोहः, वि-सं-मोहः, मूढता, मूर्खता, बुद्धि-ज्ञान-लोपः-भ्रंशः-नाशः, विवेक-हानि *f.*-लोपः.

Infeasible, *a.* असाध्य, दुष्कर, अशक्य, अनिष्पाद्नीय.

Infect, *v. t.* (अन्यस्मिन्) संचर् c., संक्रम् c., (रोगेण) संसृज् 6 P, रोगाक्रांत-*a.* कृ 8 U. 2 दुष् c. (दूषयति), भ्रंश् c.; *See* **Corrupt. -ed,** *a.* रोगदूषित-संसृष्ट-आक्रांत, संचार-संपर्क-संसर्ग-दुष्ट or दूषित. 2 दुष्ट, दूषित, भ्रष्ट. **-ion,** *s.* संचारः, संक्रमः, संसर्गः-संचार-संपर्क-स्पर्श-दोषः, रोगसंचारः-संसर्ग-संपर्कः. 2 दोषः, दूषणं. **-ious, -ive,** *a.* संचारिन्, संसर्गिन्, स्पर्शसंचारिन्, संसर्गीय, सांसर्गिक (की *f.*).

Infecund, *a.* वंध्य, निष्फल; *See* **Fruitless.**

Infelicity, *s.* असुखं, अकुशलं, अक्षेमः, दुःखं; आपद्-विपद् *f.* **-ous,** *a.* अयोग्य, अधन्य.

Infer, *v. t.* अनु-मा 3 A, 2 P, सं-भू c., उन्नी 1 P, ऊह् 1 A, तर्क् 10, अपवह् 1 P, अवगम् 1 P; 'his dignity may be i. ed from his form' संभावनीयानुभावास्याकृतिः (S. 7); 'her very form leads (me) to i. her being superhuman' आकृतिरेवानुमापयत्यमानुषतां (Ka. 132). **-able,** *a* अनुमेय, आनुमानिक (की *f.*), तर्कसाध्य गम्य. **-ence,** *s.* (Process) अनुमिति *f.* युक्ति *f.*, अपोहनं, परामर्शः. 2 (Result) अनुमानं, अपोहः, अपवाहः, तर्कः, अभ्यूहः तर्कनिर्णयः-सिद्धांतः. **-ential,** *a.* आनुमानिक आनुषंगिक (की *f.*), अनुमान-तर्क-सिद्ध.

Inferior, *a.* ऊन, न्यून, अल्पीयस्. 2 नीच हीन, नि-अप-कृष्ट, अवर, अधर, अधम्य, अधम, अनुत्तम; *See* **Mean.** 3 अधःस्थ, निम्न अधर, नीचस्थ, अधस्तन (नी *f.*). 4 गौण (णी *f.*), अप्रधान, उपसर्जन, अमुख्य; of by कु or दुर् pr., 'of an i. caste' हीनजाति-वर्ण, दुर्वर्ण, कुकुल; 'i. in rank' अवरपदभाज्; 'i. in age' कनीयस्, अवरज अनुज; 'it will be clear who is i. and who is superior' अवरोत्तरव्यक्तिर्भविष्यति (M. 1); gen. ex. by परिहा pass with abl. for 'to'; 'she is not i. to Sachi in majestic dignity' ओजस्वितया न परिहीयते शच्याः (V. 3). **-s.** अवरपदभाज् *m.*, हीनपदस्थः, अवरः. **-ity,** *s.* न्यूनता, ऊनता, हीनता, अधरता, अवरत्वं, अपकर्ष अप्राधान्यं, गौणता.

Infernal, *a.* नारक (की *f.*), नरकीय, नरकस्थ, निरयगत. 2 आसुर (री *f.*), राक्षस (सी *f.*); 'i. regions' नरकः, निरयः; पातालं, अधोभुवनं, नागलोकः, प्रेतलोकः, बलिसद्मन् *n.* —*s.* नरकवासिन् *m.*, नरकस्थः.

Infertile, *a.* *See* **Fruitless.**

Infest, *v. t.* बाध् 1 A, उप-रुध् 7 U, उप-द्रु 1 A, उप-द्रु 1 P, उपपीड् 10, उपसृज् 6 P, क्लिश् 9 P. **—ed,** *a.* उपसृष्ट, बाधित. 2 (नित्यं) सेवित, जुष्ट, आश्रित; 'i. by wild animals' श्वापदजुष्ट.

Infidel, *s.* नास्तिकः, अश्रद्धालुः, धर्मनिंदकः, अनीश्वरवादिन् *m.*, पाषंडः. —*a.* अश्रद्दधान, नास्तिकवृत्ति, अनीश्वरवादिन्, अविश्वासिन्, मिथ्यादृष्टि. **—ity,** *s.* नास्तिकता, अनीश्वरवादः, देव-धर्म-निंदा, शास्त्राश्रद्धा. 2 अभक्ति *f.*, व्यभिचारः, विवाहसमयभंगः. 3 विश्वासघातः-भंगः.

Infinite, *a.* अनंत, अमेय, अमित, अपरिमित, अपार, निर्मर्याद, निरवधि, निःसीम, अपर्यंत; 'an i. number' परार्ध्य. **—itude, —y,** *s.* आनंत्यं, अनंतता, अपारता, सीमाभावः, असीमता. **—ly,** *adv.* अमितं, अनंतं अत्यंतं, अतीव, अतिमात्रं.

Infinitesimal, *a.* अतिसूक्ष्म, अत्यंतसूक्ष्म.

Infinitive, *s.* सामान्य-साधारण-रूपं, the technical name being तुमुन्.

Infirm, *a.* दुर्बल, क्षीण, अशक्त, अवसन्न, क्षीण-बल-सत्त्व-शक्ति; *See* **Feeble.** 2 अस्थिर, स्खलित, अधीर, अदृढ; 'the step being i.' नातिस्थिरचरणसंचारस्य (Ka. 35). 3 जीर्ण, जरापरिणत, जरातुर, जरठ. **—ity,** *s.* दौर्बल्यं, अशक्तिः *f.*, वीर्य-शक्ति-हानि *f.* 2 दोषः, छिद्रं, विकारः, अपराधः, वैकल्यं, अगुणः. 3 व्याधिः, रोगः, आमयः. **—Infirmary,** *s.* आतुरशाला, रुग्णालयः.

Infix, *v. t.* *See* **Fix.**

Inflame, *v. t.* दीप् c., सं-उत्-प्र,° ज्वल् c., तप् c., दह् 1 P, सं-इंध् 7 A. 2 उत्तिज् c., प्रोत्सह् c., उद्दीप् c. (as feelings); 'will only serve to i. his grief' संदीपना एव दुःखस्य (विनोदनोपायाः) (U. 3); प्रकुप् c., रुष् c., *See* **Enrage, Excite;** 'i. ed with wrath' उद्धमन्यु, कोपज्वलित-प्रदीप्त; 'i. ed with pride' समिद्धदर्प; 'to be i.-ed' ज्वल् 1 P, दीप् 4 A. दह्-इंध् pass. **—Inflammable,** *a.* दाह्य, ज्वलनशील, आशुज्वलनीय, दाहात्मक. **—Inflammation,** *s.* तापनं, दीपनं, दाहनं. 2 तापः, दाहः, शोषः. 3 (In medicine) पाकः; 'i. of the eyes' नेत्रपाकः; अस्थिपाकः, &c. **—Inflammatory,** *a.* तापक, दीपक, दाहक, दीपन, दाहिन्, तापकारिन्. 2 दाहयुक्त-विशिष्ट, सदाह, सताप, दाह in comp.; 'i. fever' दाहज्वरः.

Inflate, *v. t.* ध्मा 1 P, श्वि c., स्फाय् c. (स्फावयति), विस्तृ c., उद्-हन् 2 P; उत्सिच् 6 P or c., उन्मथ् c.; 'i. with air' वातेन पृ c. or पूर् 10, उच्छूनीकृ 8 U. **—ed,** *a.* ध्मात, स्फीत, शून, उत्सिक्त, उद्धत, उन्मत्त; 'i. with pride' दर्पाध्मात, मदोद्धत, गर्वोद्धत, 'i. with air' वातफुल्ल, वातपूरित-पूर्ण. **—ion,** *s.* आध्मानं, वातपूरणं.

Inflect, *v. t.* नम् c., आवृज् 10, कुच् 6 P, कुंच् c. 2 विकृ c., रूपाणि आ-ख्या 2 P; 'the word is not i. ed' तच्छब्दस्य विभक्त्यादिविकारा न जायंते. **—ion,** *s.* आनति *f.*, आवर्जनं. 2 विकारः, रूपं, विभक्त्यादिकार्यं, कार्यं, विभक्ति *f.*

Inflexible, *a.* अनम्य, अनावर्ज्य. 2 दृढ, कठिन, संहत; *See* **Hard.** 3 दृढ-स्थिर-संकल्प-मति-निश्चय, धीर. 4 कठोर, कठिनहृदय, निरनुरोध, निरनुक्रोश, क्रूर. **—Inflexibly,** *adv.* सुदृढ, दृढनिश्चयपूर्वं, निर्विकल्पं, कठोरं, निरनुरोधं. **—Inflexibility,** *s.* अनम्यता, काठिन्यं, संहननं, कठोरता, धैर्यं, दृढसंकल्पत्वं.

Inflict, *v. t.* प्र-णी 1 P, प्रवृत् c., प्रयुज् 7 A, 10, आचर् 1 P, वि-धा 3 U, कृ 8 U, पत् c., आ-नि-धा; 'to i. pain on' दुःखे पत् c. or दुःखस्य पदं नी 1 P; oft. ex. by कृ or दा 3U; 'i. punishment' दंडं कृ or दा. **—ion,** *s.* प्रणयनं, विधानं, प्रवर्तनं, दानं, करणं; 'i. of punishment' दंडप्रणयनं, दंडाधानं.

Influence, *s.* बलं, प्रभावः, शक्ति *f.*, सामर्थ्यं, वशः-शं, गुणः, प्रतापः. 2 प्रतिष्ठा, गौरवं; वर्णः, अधिकारः, उत्कर्षः, पद or स्थान-गौरवं or माहात्म्यं; 'under the i. of' वश, वश्य, विधेय, अधिष्ठित, आयत्त, अधीन, तंत्र, &c. in comp.; 'under the i. of sleep' निद्रा-वश-विधेय; 'through the i. of love' कामाधीनत्वात्; 'planetary i.' ग्रहावेशः. — *v. t.* अधि-ष्ठा 1 P; प्र-भू 1 P, ईश् 2 A (with gen.); वशीकृ 8 U. 2 प्रवृत् c., प्रेर् c., प्रोत्सह् c., प्र-नि-युज् 10, नी 1 P, आकृष् 1 P, हृ 1 P; 'a fool has his mind i. ed, by the convictions of others' मूढः परप्रत्ययनेयबुद्धिः (M. 1); 'to be i. ed by' वशं गम् 1 P, विकृ pass., आयत्त-*a.* भू; 'not i. ed by anger or passions' अनायत्तो रोषस्य, अवशो विषयाणां (Ka. 45). **—Influential,** *a.* प्रतिष्ठापन्न, सप्रताप, लब्धवर्ण, प्रतिष्ठित, सगौरव; महत्, गुरु, प्रबल, प्रभाववत्; 'an i. meeting' लब्धप्रतिष्ठनराणां समाजः. **—ly,** *adv.* सप्रतापं, सप्रभावं, सगौरवं.

Influx, *s.* आगमः, अंतः-प्रवाहः-स्रवणं.

Infold, *v. t.* वेष्ट् 1 A or c., आच्छद् c., पि-धा 3 U, कोशे नि-धा. 2 **Clasp,** q. v.

Inform, *v. t.* वि-ज्ञा c. (ज्ञापयति), नि-आ-विद् c., शंस् 1 P, कथ् 10, आ-ख्या 2 P or c., बुध् c., संदिश् 6 P, श्रु c., अवगम् c. (गमयति); *See* **Tell.** 2 (Against) आ-क्रु 1 A, अभियुज् 7 A, 10, अभिशंस्, आघुष् c. **-ant,** *s.* विज्ञापकः, आ-नि-वेदकः; ख्यापकः. **-ation,** *s.* निवेदनं, विज्ञापनं, बोधनं, ख्यापनं. 2 वार्ता, प्रवृत्ति *f.*, उदंतः, वृत्तांतः, समाचारः. 3 वि-,ज्ञानं, बोधः, प्रबुद्धता, अवगमः. 4 अभियोगः, अभिशंसनं. **-er,** *s.* सूचकः पिशुनः, कर्ण(र्णे)जपः.

Informal, *a.* आविधि, नियम-विधि-रीति-विरुद्ध, उत्सूत्र. **-ity,** *s.* अविधिः, नियम or विधि-विरोधः or भंगः, अव्यवस्था, उत्क्रमः, अनियमः, अरीति *f.* **-ly,** *adv.* विधि-नियम-विरुद्धं, अयथाविधि.

Infraction, *s.* भंगः, अति-व्यति-क्रमः, लंघन, उल्लंघनं.

Infrequent, *a.* असतत, अनभीक्ष्ण, विरल, अनित्य. **-ly,** *adv.* अनित्यं, अबहुशः, कदाचित्.

Infringe, *v. t.* उत्-,लंघ् 1 A, 10, भंज् 7 P. अति-व्यति-क्रम् 1 U, 4 P, अतिचर् 1 P, लुप् c., व्याहन् 2 P. 2 भंज्, खंड् 10, भिद् 7 P. **-ment,** *s.* लंघनं, उल्लंघनं, भंगः, अति-व्यति-क्रमः, लोपः, व्याघातः.

Infuriate, *v. t.* **Enrage,** q. v. **-a.** संरब्ध, कोपाकुल, क्रोधांध; *See* **Furious.**

Infuscate, *See* **Darken.**

Infuse, *v. t.* निषिच् 6 P, संमिश्र् 10, संसृज् 6 P, समा-नि-आ-धा 3 U, प्र-नि-क्षिप् 6 P, आ-नि-प्र-विश् c. 2 कथ् 1 P; 'does not i. strength into their understanding' न तयोर्ज्ञाने शक्तिं करोति (U. 2); 'i. into the mind' उपदिश् 6 P, चित्ते निविश् c.; 'i. with perfumes' भू c., वास् 10. **-ion,** *s.* निषेकः, आधानं, प्रक्षेपः-पणं, निवेशनं, संमिश्रणं. 2 फांटः, हिमं (cold i.); निर्यासः, निर्यूहः, क्वाथः. 3 वासनं, भावनं.

Ingathering, *s.* शस्यसंग्रहः, फलसंचयः.

Ingeminate, *a.* पुनःपुनः कृत. **-v. t.** पुनःपुन कृ 8 U, द्विगुणीकृ.

Ingenious, *a.* चतुर, विदग्ध, प्रवीण, दक्ष, पटु, विचक्षण, उपायज्ञ, विज्ञ, युक्तिमत्. कल्पक, निपुण, तीक्ष्ण-सूक्ष्म-बुद्धि. 2 सुप्रयुक्त, युक्तिकृत. **-ly,** *adv.* चतुरं, सपाटवं, युक्त्या, निपुणवत्, सुप्रयोगेण. **-ness, -Ingenuity,** *s.* युक्ति *f.*, सुप्रयोगः, कल्पना, चातुर्यं, वैदग्ध्यं, पाटवं, दाक्ष्यं, कल्पकशक्ति *f.*, मतिसूक्ष्मता.

Ingenuous, *a.* निष्कपट, निर्व्याज, अमाय, शुद्धमति, अजिह्म; *See* **Frank, Honest.** 2 उदार, अभिजात, महानुभाव. **-ly,** *adv.* निष्कपटं, अमायया. **-ness,** *s.* निष्कापट्यं, अमाया, अव्याजः, सारल्यं, आर्जवं, विमलात्मता, शुद्धभावः. 2 औदार्यं, महानुभावः, आभिजात्यं.

Ingle, *s.* अग्निः. 2 उद्धानं, उष्मानं.

Inglorious, *a. See* **Infamous.**

Ingot, *s.* पिंडः; 'i. mould' तू(तु)लिका, ईषि(षी)का.

Ingraft, *v. t.* प्रतिवप् 1 P, प्रति-नि-खन् 1 P; *See* **Engraft** also.

Ingrain, *v. t.* दृढी-स्थिरी-कृ 8 U. 2 दृढं निविश् c.

Ingrate, *a.* कृतघ्न (घ्नी *f.*), अकृतज्ञ, अकृतवेदिन्. **-Ingratitude,** *s.* कृतघ्नता, अकृतज्ञता उपकारविस्मरणं-नाशनं, अकृतवेदित्वं.

Ingratiate, *v. t.* प्रसादभाजनं भू 1 P, आराध् c., प्रसद् c., अनुरंज् c., उपलल् 10, अनुग्रहं प्राप् 5 P.

Ingredient, *s.* अंगं, साधनं, भागः, अंशः, घटकः, घटकावयवः, उपकरणं.

Ingress, *s.* प्रवेशः, प्रवेशनं, प्रवेशद्वारं-मार्गः.

Ingulf, *See* **Engulf.**

Ingurgitate, *v. t.* सतृष्णं or अतिलोभेन गॄ 6 P.

Inhabit, *v. t.* वस् 1 P, नि-प्रति°, (with loc.); आ-अधि-वस्, अध्यास् 2 A, आश्रि 1 U, सेव् 1 A, जुष् 6 A, अधि-ष्ठा 1 P (all with acc.); 'thickly i. ed' जनाकीर्ण. **-able,** *a.* वासयोग्य, निवासार्ह, वासक्षम; आजीव्य. **-ant,** *s.* नि-,वासिन्-स्थायिन् *m.*, स्थः in comp ; oft. by derivatives; 'a merchant i. of Kausâmbî' कौशांबीयो वणिक्; आयोध्यकः, अत्रत्यः, तत्रत्यः, &c.

Inhale, *v. t.* श्वस् 2 P, नि-पा 1 A, अंतः ग्रह् 9 U; वायुना पूर् 10.

Inharmonious, *a.* विस्वर, कर्कशस्वन, असंगत.

Inhere, *v. i.* निवस् 1 P, नि-ष्ठा 1 P, अंतः वृत् 1 A or जन् 4 A or भू 1 P. **-ence,** *s.* निष्ठा, संस्था, अंतर्वृत्ति *f.*, अधिष्ठानं, अनुषंगः. **-ent,** *a.* निष्ठ in comp.; अंतर्जात, अंतर्वर्तिन्, निरूढ, अनुषंगिन्, समवायिन्. 2 निज, सहज, स्वभावज, स्वाभाविक-नैसर्गिक (की *f.*), प्रकृतिस्थ. **-ently,** *adv.* प्रकृत्या, स्वभावतः.

Inherit, *v. t.* अन्वयागमेन-कुलक्रमेण-प्राप् 5 P, परंपरया प्राप्, अधिकारीभू 1 P, पैतृकाधिकारं लभ् 1 A. **-ance,** *s.* रिक्थलाभः, अंश-दाय-प्राप्ति *f.*, पैतृकरिक्थप्राप्तिः. 2 दायः, रिक्थं, पैतृकं, पैतृकं धनं or रिक्थं, औद्धारिकं, क्रमागतधनं. 3 उत्तराधिकारः, रिक्थाधिकारः. 4 दायभागः. **-ed,** *a.* क्रमागत, परंपरागत-प्राप्त, क्रमायात, पैतृक (की *f.*). पितृप्राप्त, अन्वयागत. **-or,** *s.* दायादः, रिक्थाधिकारिन् *m.*; *See* **Heir.**

Inhibit, *v. t. See* **Forbid.**

Inhospitable, *a.* आतिथ्यविमुख (खी *f.*), अनातिथेय (यी *f.*), असत्कारशील, सत्कारद्वेषिन्. **-Inhospitality,** *s.* अतिथ्यनादरः-आतिथ्यविमुखता, असत्कारः.

Inhuman, *a.* अमनुष्यधर्मन्. **2** क्रूर, नृशंस, निर्दय, निर्घृण, निष्ठुर, कठोरहृदय; *See* **Cruel. -ity,** *s.* क्रौर्य, निर्दयता, नैष्ठुर्य. **-ly,** *adv.* निर्दयं, निष्ठुरं, निष्करुणं, क्रूरवत्.

Inhume, *v. t.* भूमौ निखन् 1 P or नि-धा 3 U or निविश् c. or निक्षिप् 6 P. **-ation,** *s.* निखननं, भूमौ निवेशनं.

Inimical, *a.* परिपंथिन्, वैरिन्, अहित,प्रत्यर्थिन्, विरोधिन्, विपक्ष, द्वेषिन्, प्रतिकूल; *See* under **Enemy. -ly,** *adv.* अहितबुद्ध्या, शत्रुभावेन, शत्रुवत्, शत्रु-द्रोह-बुद्ध्या, प्रतिकूलं, विरुद्धं, सवैरं.

Inimitable, *a.* असाधारण (णी *f.*), अननुकार्य, अनुपमेय, अप्रतिम, अनुपम, अद्वितीय, अनन्य-साध्य-शक्य.

Iniquity, *s.* अन्यायः, दौर्जन्यं, दुरात्मता, दुर्वृत्तता, खलता, अधर्मः, अन्याय्यता. **2** पापं, कुकर्मन् *n.*, दुराचारः, अपचारः-कर्मन् *m.*, दुष्कर्मन् *m.* महापराधः. **-ous,** *a.* अन्याय्य, धर्म्य, दुष्ट, खल, पापिष्ठ, पाप, धर्मापेत, अन्यायिन्,अधार्मिक (की *f.*); (of persons only) दुरात्मन्, दुर्जन, दुर्वृत्त, दुराचार, कुकर्मन्. **-ously,** *adv.* अन्यायेन, अधर्मेण, खलवत्, दुष्टवत्.

Initial, *a.* प्रथम, पूर्व, अग्रिम, आदिम, आद्य, प्राथमिक (की *f.*), आदि in comp. **-s.** आद्याक्षरं, आदिवर्णः, प्रथमाक्षरं.

Initiate, *v. t.* आरभ् 1 A, उपक्रम् 1 A, प्रस्तु 2 U. **2** प्रथमतस्थानि उपनी 1 A, अभिमंत्र् 10 A, उपदिश् 6 P, दीक्ष् 1 A, (संस्कारपूर्व) प्रविश् c. **-ed,** *a.* दीक्षित, कृतसंस्कार, उपनीत, कृतदीक्ष, अभिमंत्रित. **2** कृतविद्योपक्रम, विद्याप्रविष्ट, कृतप्रवेश. **-ion,** *s.* आरंभः, उपक्रमः, प्रथमशिक्षा-उपदेशः,विद्यातत्त्वोपदेशः, दीक्षा, संस्कारः, अभिमंत्रणं, उपनयः, विद्याप्रवेशः. **2** दीक्षाकरणं. **-ive,** *s.* आरंभः, उपक्रमः. **-a., -ory,** *a.* आद्य, आरंभक, उपक्रमकारिन्.

Inject, *v. t.* अंतः प्रविश् c. or निक्षिप् 6 P. **-ion,** *s.* अंतःक्षेपणं.

Injudicious, *a.* अविवेकिन्, अविचक्षण, विचार-विवेक-शून्य, विचारहीन असमीक्ष्यकारिन्-कृत; *See* **Indiscreet.**

Injunction, *s.* शासनं, आज्ञा, आ-नि-देशः, नियोगः; ' sacred i. ' विधिः, कल्पः, चोदना; ' scriptural i. ' शास्त्रचोदना, धर्मसूत्रं, शास्त्राज्ञा.

Injure, *v. t.* पीड् 10, नि-अप-कृ 8 U, दु 5 P, हिंस् 7 P (a strong term) ; सं-, बाध् 1 A, अर्द् 1 P or c., क्षण् 8 P, क्षि 1, 5 P or c., दुष् c. (दूषयति), व्यथ् c. (व्यथयति), द्रुह् 4 P (with dat.), अपराध् 4, 5 P (with loc. or gen.). **-er,** *s.* अपकर्तृ *m.*, पीडकः, हिंसकः, अपकारकः, द्रोहिन् *m.* **-ious,** *a.* पीडाकर-अनिष्टकर-हानिकर-अहितकर (री *f.*), अहित, बाधक, अपकारक, हिंसक, द्रोहिन्, घातक, घातुक, हिंसात्मक, हिंस्र, हिंसालु, शरारु, नृशंस. **-iously,** *adv.* सापकारं, सापायं, हिंसा-क्षति-पूर्व. **-y,** *s.* पीडा, अपकारः, अपकृति *f.*, अपक्रिया, अपायः, हिंसा, अहितं, अनिष्टं, हानि *f.*, निकृतिः, अन्यायः, द्रोहः, अपराधः. **2** क्षति *f.*, क्षतं, बाधा. **3** नाशः, क्षयः, अपचयः.

Injustice, *s.* अन्यायः, अधर्मः, अनीति *f.*, दुर्नीतिः, न्याय-धर्म-विरोधः, अनयः.

Ink, *s.* मसि-सी (मषि-षी) *f.*, मेला, गोला; ' red i. ' अलक्तः, अलक्तरसः; ' i.-stand ' मसीपात्रं, मस्याधारः, मसिकूपी-भाजनं-धानी, मेलान्धुकः, वार्दलः; ' bring i. and paper ' मसीभाजनं पत्रं चोपनय (Mu. 1). **-v. t.** मस्या लिप् 6 P or c. दुष् (दूषयति). **-y,** *a.* मसीलिप्त, मसीवर्ण-दूषित.

Inkling, *s.* यत्किंचिदवबोधनं, ईषज्ज्ञानं, इंगितं, किंचिद्बोधनं.

Inland, *a.* देशीय, दैशिक-आभ्यंतरिक (की *f.*) देश in comp. **2** देशमध्यवर्तिन्, देशमध्यस्थ. **-er,** *s.* देशमध्यवासिन् *m.*

Inlay, *v. t.* प्रतिबंध् 9 P, (यदि मणिस्त्रपुणि प्रतिबध्यते P. 1. 1), प्रतिवप् 1 P, प्रणि-धा 3 U, अनु-व्यध् 4 P, खच् 10 (खचयति), जुड् 6 P or c.

Inlet, *s.* द्वारं, प्रवेशः, प्रवेशद्वारं-मार्गः. **2** पुटभेदः, समुद्रवंकः.

Inly, *adv.* अंतर्; अन्तरस्थ *a.*

Inmate, *s.* निवासिन् *m.*, सहवर्तिन् *m.*; gen. परिजनः, भृत्यवर्गः.

In memoriam, *adv.* स्मरणार्थं.

Inmesh, *See* **Enmesh.**

Inmost, *a.* अत्यभ्यंतर, अत्यंतर्भूत; gen. ex. by उदरं, गर्भः, अंतर् in comp. ; 'i. heart' हृदयोदरं; ' i. soul' अंतरात्मन् *m.*

Inn, *s.* पथिकाश्रमः, मठः, उत्तरणस्थानं. **2** स्मृतिशास्त्रज्ञवासः. **3** शुंडा,पानस्थानं, मदिरागृहं-शाला; ' i.-keeper ' पथिकाश्रमपतिः, शौंडिकः.

Innate, *a.* सहज, स्वभावज, निज, स्वाभाविक-नैसर्गिक (की *f.*), निसर्गज,प्रकृतिस्थ. **-ly,** *adv.* स्वभावतः, निसर्गतः.

Innavigable, *a.* अनौगम्य.

Inner, *a.* अंतरस्थ, अंतर्भूत, अंतर्गत, अंतरवर्तिन्, अंतरीय, आंतर-आभ्यंतर (री *f.*); oft. by अंतर, अंतर्, गर्भ, उदर in comp.; ' i. apartments ' अंतर्गृहं, भवनोदरं, वासगर्भः.

Innermost, *See* **Inmost.**

Innocent, *a.* निरपराध, अकृतापराध, अदोष, अपाप, निष्पाप, अनघ, अनागस्, निर्मल, निर्दोष, शुचि, निष्कलंक, अनवद्य. 2 मुग्ध, मुग्धस्वभाव; अहेतुक, अनिमित्त, निष्कारण; 'i. smile' अनियतस्मितं, अनिमित्तहासः. 3 निरुपद्रव, अनुपद्रविन्, अद्रोहिन्, अहिंस्र, अघातुक, अनपकारिन्. 4 शुद्धमति, निर्मलचित्त, निष्कपट, निर्व्याज, सरल, अकृत्रिम, निर्व्यलीक. **-ly**, *adv.* निरपराधं, दोषं-पापंविना, शुचि, निष्कपटं. **-Innocence,-cy,** *s.* निरपराधता, शुचिता, निर्दोषता, अनघता, दोषमुक्ति *f.*; निष्कापट्यं, सारल्यं, &c.

Innocuous, *a.* अहिंस्र, अहिंसक, अनुपद्रविन्, अनपकारिन्, अद्रोहिन्, अघातुक. **-ly**, *adv.* अनपकारं, अहिंसापूर्वं, अहिंसया. **-ness**, *s.* अहिंसा, अनपकारः, अद्रोहः, अक्षति *f.*

Innominate, *a.* नामरहित, निर्नामन्.

Innovate, *v. t.* नूतनरीतिं-व्यवहारं-संप्रदायं-स्था c. (स्थापयति) or प्रवृत् c. or कृप् c., देशाचारं परिवृत् c. **-ion**, *s.* नूतनमार्गप्रवर्तनं, नवाचारस्थापनं, देशाचारपरिवर्तनं. 2 नूतना रीतिः, नवरीतिः-व्यवहारः, नवाचारः, नूतनमार्गः-पद्धति-सरणि *f.*, रीत्यंतरं. **-or**, *s.* नवमार्गप्रवर्तकः, नवरीतिस्थापकः.

Innoxious, *a. See* **Innocuous.**

Innuendo, *s.* भंगि-गी *f.*, वक्रोक्ति *f.*, व्यंगोक्तिः, भंग्युक्तिः, छेकोक्तिः, वक्र-भंगिभाषितं.

Innumerable, *a.* असंख्य, गणनातीत, संख्यातीत, अगण्य, असंख्येय.

Inoculate, *v. t.* (अन्यस्मिन् स्थाने) निविश् c., संक्रम् c., संचर् c. **-ion**, *s.* निवेशनं, संचारणं.

Inodorous, *a.* निर्गंध, गंधहीन.

Inoffensive, *a.* अक्लेशद, अनुपद्रविन्, अबाधक, अद्रोहशील, निरपराध; अपीडामद, आहस; *See* **Innocent, Innocuous.** **-ness**, *s.* अहिंसा, अद्रोहः, अनपकारः, हिंसाविरति *f.*, अनपकारिता, अद्रोहशीलता.

Inoperative, *a.* अकार्यसाधक, अकिंचित्कर (री *f.*).

Inopportune, *a.* अप्राप्तकाल, अनवसर, असमयोचित, अस्थान, अयोग्य, अप्रस्तावयोग्य, असमयानुरूप, अ(आ)कालिक (की *f.*). **-ly**, *adv.* अकाले, अस्थाने, अप्राप्तकालं, अनवसरं, अयथाकालं. **-ness**, *s* अनवसरः, असमयः, अकालिकत्वं.

Inordinate, *a.* अत्यंत, उद्रिक्त, अतिरिक्त, अमित, अपरिमित, अतिमात्र, अमर्याद. **-ly**, *adv.* अत्यंतं, अतिमात्रं, नि-सु-तरां, सातिशयं, अतीव. **-ness**, *s.* उद्रेकः, अतिरेकः, अत्यंतता, अमितत्वं; *See* **Excess, Excessive,** &c.

Inorganic, *a.* निर्जीव, अप्राणिन्, जड.

Inquest, *s.* विचारः-रणा, व्यवहारदर्शनं. 2 अपमृत्युविचारणा.

Inquietude, *s.* अशांति *f.*, अस्वास्थ्यं, उद्वेगः, वैक्लव्यं, आकुलता, चित्तवेदना, मनस्तापः.

Inquire, (of, after) *v. t.* प्रच्छ् 6 P, अनुयुज् 7 A. 2 अन्विष् 4 P, मृग् 10 A, गवेष् 10, ज्ञा desid. (जिज्ञासते). 3 (into) अव-परि-ईक्ष् 1 A, विचर् c., विमृश् 6 P, चर्च् 6 P, 10 A, निरूप् 10, अनुसं-धा 3 U, परिच्छिद् 7 P, निर्णी 1 P, निश्चि 5 U; 'i. about one's health' सुखं-कुशलं-प्रच्छ्, (देवीं सुखं प्रष्टुमागता M. 4). **-er**, *s.* प्रष्टृ *m.*, पृच्छकः, अनुयोक्तृ *m.*, जिज्ञासुः, अन्वेषकः. 2 परीक्षकः, निरूपकः, विचारकः. निर्णेतृ *m.* **-y**, *s.* अनुयोगः, पृच्छा, प्रश्नः. 2 जिज्ञासा, अन्वेषणं, मार्गणं. 3 परीक्षा-क्षणं, अनुसंधानं, निरूपणं, विचारः-रणा, निर्णयः, चर्चा, विमर्शः, निश्चयः, विवेचनं; 'i. about one's well-being (health)' अनामयकुशल-प्रश्नः.

Inquisition, *s.* परीक्षणं, विचारः; *See* above. 2 धर्मविचारणसभा.

Inquisitive, *a.* जिज्ञासु, प्रश्न-पृच्छन-शील, कुतूहलिन्, कौतुकवत्, कौतुकाविष्ट, अनुसंधान-अन्वेषण-शील. 2 ज्ञानेप्सु. **-ly**, *adv.* सकौतुकं, कुतूहलात्, जिज्ञासापूर्वं, कुतूहलेन. **-ness**, *s.* कु(कौ)तूहलं, कौतुकं, जिज्ञासा, पिपृच्छिषा, ज्ञानेच्छा, अन्वेषणशीलता, अनुसंधानेच्छा.

Inquisitor, *s.* परीक्षकः, विचारकः, निरूपकः. 2 धर्मविचारसभासद् *m.* **-ial**, *a.* अतिपरीक्षकनिरूपक, अतिचर्चक. **-ially**, *adv.* अतिचर्चया, अतिपरीक्षापूर्वं.

Inrail, *v. t.* शंकुपंक्त्या परिवेष्ट c. or आ-वृ 5 U.

Inroad, *s.* अवस्कंदः-दनं, आपातः, आक्रमणं, उपप्लवः, उप-अभि-द्रवः, अभिनिर्याणं; 'to make i. s' अवस्कंद् 1 P, अभिद्रु 1 P; *See* **Attack.**

Inrush, *s.* सरभसप्रवेशः; *See* **Inroad.**

Insalubrious, *a.* अनारोग्य, अक्षेमकर (री *f.*), अक्षेम्य, अहित.

Insalutary, *a.* अहित, अक्षेम्य, अहित-अनिष्ट-अक्षेम-असुख-कर (री *f.*).

Insane, *a.* उन्मत्त, भ्रांतचित्त, उन्मादिन्, सोन्माद, हत-नष्ट-विक्षिप्त-बुद्धि, वातुल, हतज्ञान, भ्रष्टबुद्धि. **-ly**, *adv.* सोन्मादं, उन्मत्तवत्. **-ness, Insanity**, *s.* उन्मादः, चित्तभ्रमः, बुद्धिभ्रंशः-नाशः, चित्तविप्लवः.

Insanitary, *a.* आरोग्यविघातक, रोगावह.

Insatiable, Insatiate, *a.* अतोषणीय, अतृप्त, अतर्पणीय, दुस्तोष. 2 अतिलुब्ध, अतिलोलुप *See* **Greedy.**

Inscribe, *v. t.* अभिलिख् 6 P, पत्रे-लेख्ये निविश् c. or ऋ c. (अर्पयति) or न्यस् 4 U

or आरुह् c. 2 वर्ण् अंक् 10 or चिह्न् 10. 3 Dedicate, q. v. -ed, *a*. अभिलिखित, प्रशस्त, न्यस्ताक्षर, लेख्यारोपित ; 'writing i. ed on a Bhûrja leaf' भूर्जपत्रगताक्षराणि. -Inscription, *s*. लेखः, लेख्यं, लिखितं. 2 पाषाण-शिला-लेखः.

Inscrutable, *a*. अतर्क्य, दुर्ग्राह्य, अचिंत्य, दुर्बोध, अलक्ष्य, बोधातीत, गहन, दुर्ज्ञेय, अज्ञेय, अगाध. -y, *adv* परमगहनं, दुर्ज्ञेयतया.

Insculp, *v. t*. तक्ष् 1, 5 P.

Insect, *s*. कृमिः, कीटः, क्रिमिः, नीलं(लां)गुः. -ivorous, *a*. कीटभोजिन्, कृमिभुज्.

Insecure, *a*. शंकान्वित, संशय-संदेह-स्थ, सशंक, भयान्वित, संशय-शंका-आपन्न, भययुक्त, असुरक्षित, अक्षेम. -ity, *s*. भयं, शंका. अक्षेमः-मं. भयशंका-संशयः.

Insensate, *a*. मूढ, निर्बुद्धि, हतज्ञान, अचेतन; *See* Foolish under Fool.

Insensible, *a*. अ-वि-गत-नष्ट-चेतन, सुप्त, स्पर्शानभिज्ञ, सुप्त-नष्ट-इंद्रिय, प्र-,मूढ, लुप्तसंज्ञ, निःसंज्ञ, नष्टचेष्ट-संज्ञ, संज्ञा-चेष्टा-चैतन्य-हीन or रहित, प्रलीन, मूर्च्छित. 2 अगोचर, दुर्लक्ष्य, अलक्ष्य, इंद्रियागोचार, इंद्रियातीत, अतींद्रिय. 2 अनार्द्रचित्त, कृपा-दया-हीन, राग-रस-हीन, निर्दय, निष्कृप. 4 जड, कुंठ, मूढ, मूर्ख. 5 (Unaware) अनभिज्ञ, अज्ञ ; ex. by not Know, q. v.; 'i. to pain' अवेदनाज्ञ, दुःखानभिज्ञ. -ness, -Insensibility, *s*. प्रमोहः, प्रलयः, मूर्च्छा, संज्ञा-चेतना-चैतन्य-हानि *f*. or नाशः, अचैतन्यं, अचेतना, इंद्रियसुप्ति *f*. -नाशः, स्पर्शाज्ञानं, अचेतनत्वं, नष्टचेष्टता. 2 राग-भाव-हीनता, दयाहीनता. 3 जडता, जाड्यं, जडिमन् *m*. 4 अनभिज्ञता, अबोधः, अज्ञानं. -Insensibly, *adv*. अलक्ष्यं; क्रमेण, शनैः, शनैः शनैः, क्रमशः.

Inseparable, *a*. अवियोज्य, अविभेद्य, समवायिन्, नित्यसंहवर्तिन्; 'i. relation' समवायसंबंधः. Inseparably, *adv*. नित्यसंबंधेन, समवायसंबंधेन.

Insert, *v. t*. नि-आ-प्र-विश् c., प्रत्याकल् 10, नि-धा 3 U, अंतः स्था c. (स्थापयति), or न्यस् 4 P; 'i. in writing' अभिलिख् 6 P, लेख्ये आरुह् c. (रोपयति) or सम्-ऋ c. (अर्पयति). -ion, *s*. निवेशः-शनं, निधानं, आ-प्र-वेशनं.

Inset, *v. t*. प्रक्षिप् 6 P, नि-विश् c. -*a*. प्रक्षिप्त, निवेशित. -*s*. प्रक्षेपः, निवेशनं.

Inside, *s*. अभ्यंतरं, अंतरं, उदरं, गर्भः, क्रोडं, अंतर्भागः; 'the i. of a house' अंतर्गृहं, भवनोदरं; 'i. of a tree' तरुक्रोडं, कोटरं. -*adv*. अभ्यंतरे, गर्भे, अंतरे, अंतः.

Insidious, *a*. सव्याज, सकपट, छलिन्, मायाविन्, कापटिक (की *f*.); *See* Fraudulent. -ly, *adv*. समायं, सकपटं, सव्याजं, छलेन. -ness, *s*. कापट्यं, मायित्वं, सव्याजता.

Insight, *s*. ज्ञानं, परिज्ञानं, परिचयः, प्रनिवेशः, निरीक्षणं.

Insignia, *s*. लक्षणं, चिह्नं, लिंगं, व्यंजनं, लांछनं, लक्ष्मन् *n*.

Insignificant, *s*. निरर्थक, अनर्थक, अर्थहीन-शून्य; not Significant, q. v. 2 अगुरु, लघु, अल्पप्रभाव, अकिंचित्कर (री *f*.). 3 तुच्छ, क्षुद्र, नीच, अल्पक, कदर्य, अपकृष्ट, तृणप्राय, निःसत्त्व; oft. by कि-का- in comp.; कापुरुषः 'i. man'. -ly, *adv*. निरर्थकं, अर्थं विना. 2 लघुतया, लाघवेन, अगौरवेण. -Insignificance, -cy, *s*. अनर्थकत्वं, वैयर्थ्यं, अर्थाभावः, आनर्थक्यं. 2 लाघवं, अगौरवं, लघिमन् *m*., अल्पत्वं. 3 क्षुद्रता, अपकर्षः, तुच्छता.

Insincere, *a*. सव्याज, सकपट, कितव, कापटिक-छाद्मिक-(की *f*.), वक्र, मायिन्, कुटिल, कृतक, कृत्रिम, असत्य, वितथ, अलीक, अनृत, मृषार्थक, मिथ्या-मृषा-in comp.; *See* False. Deceitful. -ity *s*. कापट्यं, असारल्यं, कौटिल्यं, छद्मन् *n*., दंभः, माया, जिह्मता, असत्यता, अलीकता, कृत्रिमता. -ly, *adv*., सकपटं, सव्याजं, असरलं, असत्यं, अयथार्थं, मृषा, मिथ्या।

Insinuate, *v. i*. मंदं मंदं विसृप् 1 P or प्रविश् 6 P or अंतर्गम् 1 P. -*v. t*. भंग्या आक्षिप् 6 P or सूच् 10; वक्रोक्त्या उपन्यस् 4 U or उद्दिश् 6 P or उपाक्षिप्. 2 सामोपचारैः लल् 10 or सांत्व् 10 or आराध c. or अनुरंज् c. or परानुग्रहं प्राप् 5 P. -ing. *a*. लालन-सांत्वन-शील. 2 वक्रोक्त्या सूचक. -ion, *s*. वक्रोक्ति *f*., कटाक्षाक्षेपः, भंगिभाषणं, छेकोक्तिः, भंग्युक्तिः, व्यंग्योक्तिः, वक्रभणितं भाषितं-वाक्य. 2 लालनं, शनैः परानुग्रहसंपादनं.

Insipid, *a*. अनास्वाद-रस-नीरस, रसहीन, अस्वादु, लवणहीन. 2 असार, निःसार, निःसत्त्व, फल्गु, निस्तेजस्. -ity, -ness, *s*. वैरस्यं, नीरसता, अस्वादुता, अरसता, असारता. फल्गुता.

Insipience, *s*. अज्ञानं, मौर्ख्यं. -Insipient, *a*. अज्ञ, मूर्ख.

Insist, *v. i*. ग्रहं न मुच् 6 P, निर्बंधेन वद् 1 P or कथ् 10, अतिनिर्बंधेन अव-स्था 1 A or अवलंब् 1 A, दृढोक्त्या वद् or सूच् 10; 'I i. ed on his following me' त्वयावश्यमहमनुसर्तव्य इति निर्बंधेन तमवदम्; 'i. ed on her demands' प्रार्थनाविषये स्वं ग्रहं न मुमोच; *See* Importune.

Insnare, *See* Ensnare.

Insobriety, *s*. मत्तता, क्षीबत्वं. 2 मद्यपानासक्ति *f*.

Insociable, *a*. संसर्गविमुख संलापिन्, असंलाप-असंसर्ग-शील.

Insolate, *v. t.* सूर्यकिरणैः व्याप् c.

Insolent, *a.* दृप्त, गर्वित, मत्त, उद्धत, मदोद्धत, अवलिप्त, उत्सिक्त. 2 धृष्ट, अविनीत, प्रतिभावत्, वियात, निर्लज्ज, प्रगल्भ, सावहेल, अमर्याद. **-ly,** *adv.* सदर्पं, सावलेपं, सगर्वं, धृष्टतया, सधर्षं, प्रगल्भं, अविनयेन, सावहेलं, अमर्यादं. **-Insolence,** *s.* औद्धत्यं, अवलेपः, दर्पः, गर्वः, उत्सेकः. 2 वैयात्यं, अविनयः, प्रागल्भ्यं, धार्ष्ट्यं, प्रतिभानं, धृष्टता.

Insoluble, *a.* अद्राव्य, अभेद्य, अविलयनीय.

Insolvent, *a.* परिक्षीण, गतविभव, निर्धन, ऋणशोधनाक्षम.

Insomnia, *s.* अस्वापः, निद्रानाशः, अनिद्रता.

Insouciant, *a.* प्रमत्त, अनवहित.

Inspan, *v. t.* धुरि युज् c.

Inspect, *v. t.* ईक्ष् 1 A; सं-परि-अव-निर्-वि°-, निरूप् 10, दृश् 1 P, आ-अव-लोक् 1 A, 10, आलोच् 10, अनुसं-धा 3 U. **-ion,** *s* निरीक्षणं, अवेक्षणं, निरूपणं, दर्शनं, आलोकनं. 2 अनुसंधानं, कार्यदर्शनं. 3 अध्यक्षता, अधिकारः, अवेक्षा. **-or,** *s.* द्रष्टृ *m.*, निरूपकः, निरीक्षकः. 2 अध्यक्षः, अधिकारिन् *m.*, अवेक्षकः, कर्माधिकारिन् *m.* कार्यद्रष्टृ *m.*. कार्याध्यक्षः, कार्याधीशः. **-orship,** *s.* अध्यक्षता, कार्याधीशता

Inspersion, *s.* अभिषेकः, प्रोक्षणं.

Inspire, *v. i.* श्वासेन पृ c. or पूर् 10, श्वस् 2 P, प्राणं आकृष् 1 P. 2 निविश् c., नि-धा 3 U, उपनि-धा, उत्पद् c., जन् c. (जनयति), प्रबुध् c., उपन्यस् 4 U, उपक्षिप् 6 P. 3 आश्वस् c., उत्तिज् c., प्रेर् c., प्रोत्सह् c., संचर् c., उद्युक्ष् 10, प्रवृत् c., धैर्य-तेजः-उत्पद् c ; 'divine speech suddenly i. ed' आकस्मिकप्रत्ययभासां देवीं वाचं (U. 2); 'i. ed life into him' स सोच्छ्वासमकरोत्; 'i. ed with a passion for Rambhā' रंभायां बद्धभावः, बद्धानुरागः, कृतप्रणयः; 'i. with confidence' विश्वस् c., विश्वासं नी 1 P or जन् c.; 'i. s with awe' भयं जनयति (प्रथमोपगतस्य) (Ka. 43). **-ation,** *s.* श्वसितं, श्वसनं, उच्छ्वासः, श्वासः, प्राणः, श्वासप्राण-ग्रहणं, श्वासेन पूरणं. 2 निवेशनं, आधानं, जननं, उत्पादनं. 3 अवभासः, आकस्मिकोद्भवः, ईश्वरप्रेरणा-सूचना-प्रबोधः, ईश्वरप्रेरितं ज्ञानं, दैवज्ञानं. **-ed,** *a.* निवेशित, जनित, उत्पादित, निहित. 2 प्रेरित, संचारित, ईश्वरप्रेरित-संचारित-प्रबोधित, आकस्मिकप्रत्ययभास. 3 आश्वासित, जातविश्वास, प्रोत्साहित, उत्तेजित; oft. by जात in comp.; 'thus i. with confidence' एवं जातविश्वासः, जातभयः, &c.

Inspirit, *v. t.* उत्तिज् c., प्रोत्सह् c., आश्वस् c., उल्लस् c , प्रबुध् c., जीव् c., जीवं-तेजः-धैर्यं आ-धा 3 U or उत्पद् c. or दा 3 U. **-ing,** *a.* उत्तेजक, प्रोत्साहक, आश्वासक, उत्साहप्रद.

Inspissate, *v. t.* घनी-सान्द्री-कृ 8 U, संहन् 2 P. **-a.,-ed,** *a.* घनीभूत, घन, सान्द्र, संहत, निबिड. **-ion,** *s.* घनता, सान्द्रता, गाढता.

Instable, *a.* See **Unstable. -Instability,** *s.* अस्थैर्यं, चंचलता, चापल्यं, अनवस्था, अस्थायित्वं, अनित्यता.

Install, *v. t.* यथाविधि प्रतिष्ठा c. (प्रतिष्ठापयति), अधिकारे नियुज् 7 A, 10, अधिकारारूढ-पदस्थ-*a.* कृ 8 U, अभिषिच् 6 P, (with loc.); 'i. as heir apparent' यौवराज्याभिषेकं कृ, यौवराज्ये अभिषिच्. 2 संस्कृ, अभि-अनु-मंत्र् 10 A. **-ation,** *s.* प्रतिष्ठापनं, अभिषेकः, नवाधिकार-प्रवेशनं-प्रतिष्ठा-संस्कारः, पदस्थापनं, राज्याभिषेकः. **-ed,** *a.* प्रतिष्ठापित, प्रतिष्ठित, अभिषिक्त, कृताभिषेक, कृतसंस्कार, कृत-लब्ध-प्रतिष्ठ, नवाधिकारप्रवेशित, अधिकार-पद-आरूढ.

Instalment, *s.* भागः, अंशः, ऋणभागः; 'by i. s' अंशांशतः, विभागशः, भागतः.

Instance, *s.* उदाहरणं, निदर्शनं, दृष्टांतः, उदाहारः. 2 पदं, स्थलं, विषयः, स्थानं. 3 प्रस्तावः, समयः, अवसरः. 4 प्रार्थना-नं, निर्बंधः, प्रेरणा; 'at his i.' तत्प्रेरितः; 'for i.' तथाहि, यथा, दृष्टांतरूपेण; 'as for i.' तद्यथा; 'in the first i.' प्रथमतः, प्रथमं, प्रथमसमये. **-v. t.** दृष्टांतरूपेण कथ् 10, निदृश् c., दृष्टांतयति (D.).

Instant, *a.* सद्यः in comp., तात्कालिक-साधक (की *f.*), अनंतरकालीन, अव्यवहितकाल, क्षिप्र, शीघ्र, अचिर. 2 निर्बंध-आग्रह-शील, अतियाचक-प्रार्थक. 3 वर्तमान; 'i. death' सद्योमृत्युः; 'bearing an i. fruit' सद्योविपाक. **-s.** क्षणः, पलं, निमि(मे)षः, मात्रा; 'the present i.' आपातः ; 'in an i.' क्षणात्, क्षणेनैव, निमेष-क्षण-मात्रेण, एकपदे; 'for an i.' क्षणमात्रं, क्षणं; 'the i.' ex. by एव, मात्र in comp., or यावत् तावत्; 'at that (very) i.' तत्काले एव, तत्क्षणे; 'every i.' प्रति-अनु-क्षणं, क्षणे क्षणे; 'the next i.' क्षणांतरं; 'from the i. of birth' जातमात्र-*a.* **-aneous,** *a.* क्षणस्थायिन्, अचिर, तात्कालिक-तत्क्षणिक (की *f.*), क्षणिक. **-aneously,** *adv.* क्षणेन-णात्, एकपदे, सद्यः, तत्काले, तत्क्षणे; See below. **-ly,** *adv.* सपदि, द्राक्, तत्क्षणं-णे-णेन, झटिति, सद्य एव, क्षण-निमेष-मात्रेण, क्षणेन, क्षणाद् एव, अंजसा.

Instate, *v. t.* पदं आ-रुह् c. (रोपयति), प्रति-ष्ठा c. (-ष्ठापयति), प्रविश् c.

Instauration, *s.* प्रतिष्ठापनं, प्रतिसमाधानं.

Instead (**of**), *prep.*, *adv.* (Before nouns) ex. by स्थाने, स्थले, भूमौ, विनिमयेन, in comp.; 'i. of my brother' भ्रातृस्थाने; तिलविनिमयेन, &c.; (before participles) ex. by loc. abs. with pot

pass. part.; 'i. of saying *on Purushottama*' पुरुषोत्तमे इति भणितव्ये (V. 3); 'i. of studying, why do you play' अध्ययने आरब्धव्ये किमिति क्रीडसि; 'be not sorry i. of being glad' हर्षस्थाने अलं विषादेन (V. 2).

Insteep, *v. t.* आर्द्र् 10, प्लु c., सिच् 6 P or c., आप्लु c.

Instep, *s.* पिच्छ (च्छिं)डिका, पिंडि-डी *f.*, पिंडिका.

Instigate, *v. t.* प्रोत्सह् c., उत्तिज् c., उद्-नि-युज् 10, प्रेर् c., प्रचुद् 10, प्रवृत् c., प्रणुद् c., उद्दीप् c., उत्-स्था c. (उत्थापयति), प्रवृत् c. **-ion,** *s.* प्रोत्साहनं-ना, प्रेरणं-णा, प्रचोदनं-ना. **-or,** *s.* प्रोत्साहकः, प्रवर्तकः, उत्तेजकः, प्रेरकः.

Instil, *v. t.* लवशः-अल्पाल्पं-निषिच् or निक्षिप् 6 P, शनैः शनैः प्र-नि-विश् c. or उपदिश् 6 P or शास् 2 P.

Instinct, *s.* सहजज्ञानं, अशिक्षितबोधः, स्वाभाविक-नैसर्गिक-सहज-बुद्धि *f.*, स्वाभाविकज्ञानं; 'natural i.' सहजावबोधः. **-a.** उत्तेजित, उद्दीपित, उद्दीप्त. **-ive,** *a.* सहज, सहजज्ञानसिद्ध, प्रकृतिसिद्ध, सहजात, स्वाभाविक-नैसर्गिक (की *f.*), स्वभावप्रेरित, **-ively,** *adv.* अंतःप्रवृत्त्या, स्वयं, स्वत एव, स्वभावतः, सहजावबोधेन.

Institute, *v. t.* प्रारभ् 1 A, उपक्रम् 1 A, प्रवृत् c., प्रस्तु 2 U; स्था c. (स्थापयति), प्रति-व्यव-सं.° 2 प्र-परि-क्लृप् c., वि-धा 3 U, आ-निर्-दिश् 6 P, प्रचुद् 10, शास् 2 P. **-s** व्यवस्था, स्थिति *f.*, विधिः, नियमः, कल्पः सूत्रं, शास्त्रविधानं-मर्यादा-निदर्शनं, नियोगः चोदना; 'religious i. s' धर्मशास्त्रं; 'i. s of Manu' मनुसंहिता, मनुस्मृतिशास्त्रं. **-ion,** *s.* स्थापनं, कल्पनं, विधानं. 2 विधिः, नियमः रीति *f.*, मार्गः; *See* (*s.*). 3 शाला, आलयः मंदिरं, सभा; श्रेणि-णी *f.*, संसर्गः, संस्थानं समाजः; 'religious i.' धर्मसंस्थानं-शाला. 'educational i.' विद्यालयः, ज्ञानमंदिरं. **-or,** *s.* संस्थापकः, प्रवर्तकः, आरंभकः.

Instruct, *v. t.* अनु-,शास् 2 P, शिक्ष् c., उपदिश् 6 P, अधि-इ c. (अध्यापयति), पठ् c., विनी 1 P. 2 बुध् c., ज्ञा c. (ज्ञापयति), नि-आ-विद् c., सूच् 10. 3 आ-निर्-सं-दिश्, आ-ज्ञा c., नियुज् 7 A, 10, प्रचुद् 10. **-ion,** *s.* उपदेशः, शिक्षा-क्षणं, विनयनं, अध्यापनं, शासनं, बोधनं. 2 विधिः, नियमः, सूत्रं, कल्पः. 3 आज्ञा, नि-आ-देशः, शासनं, नियोगः. **-ive,** *a.* उपदेशक, उपदेशप्रद, बोधावह बोधपर (री *f.*), बोधक. **-or,** *s.* शिक्षकः, गुरुः, उपाध्यायः, उपदेशकः, अध्यापकः, उपदेष्टृ *m.*, आचार्यः. **-Instructress,** *s.* उपदेशी, आचार्या, उपाध्याया-यी, अध्यापिका.

Instrument, *s.* यंत्रं, साधनं; कार्यसाधनं, उपकरणं, सामग्री, उपस्करः, द्रव्यं. 2 कारणं, करणं, हेतुः, निमित्तं, निमित्तकारणं. 3 कारकः, साधकः, कर्तृ *m.*, कारकहेतुः. 4 लेखः, लेख्यं, पत्रं, लेखपत्रं; 'serving as the i. of others' परोपकरणीकृत-भूत; 'where such persons become helping i. s' यंत्रोपकरणीभावमापद्यन्ते यस्मिन्विधौ जनाः (U. 3); 'musical i.' वादित्रं, वाद्यं, तूर्यं, आतोद्यं; 'a wind-i.' सुषिरं, शंखः; 'stringed i.' तंत्रीः; तंतुवाद्यं; 'martial i.' रणवाद्यं. **-al,** *a.* Ex. by साधनं, कारणं, हेतुः, निमित्तं; 'he was i. in elevating me' स ममोन्नतौ कारणं-हेतुः; साधक, साधन-कारण-भूत, साधनी-कारणीभूत, उपकारक. 2 वाद्यज, वाद्यसंभूत, वाद्योत्पन्न. 3 करणं, तृतीयाविभक्ति *f.* **-ality,** *s.* कारणत्वं, कर्तृत्वं, करणत्वं, साधनत्वं; *See* **Through.** **-ally,** *adv.* कारणतः, निमित्ततः.

Insubordinate, *a.* अविधेय, अवश, अवशवर्तिन्, अनायत्त, अविनीत, अनुपसर्जन, अगौण (णी *f.*). **-ion,** *s.* अविनयः, अविधेयता, शासन or आज्ञा-भंगः or व्यतिक्रमः, अवशता, अगौणता.

Insubstantial, *a.* अ-निः-सार, निःसत्त्व, अवास्तविक (की *f.*).

Insufferable, *a.* असह्य, दुःसह, अक्षंतव्य.

Insufficient, *a.* अपर्याप्त, न्यून, अयथेष्ट, अल्प, अप्रचुर, हीन, क्षीण, अनलं *ind.* 2 अनुचित, अक्षम, अयोग्य. **-ly,** *adv.* अनलं, अप्रचुरं, अपर्याप्तं. 2 अनुचितं, अयोग्यं. **-Insufficiency,** *s.* न्यूनता, अपर्याप्ति *f.*, अल्पत्वं, अबाहुल्यं, हीनता, अप्राचुर्यं. 2 अक्षमता, अनौचित्यं.

Insular, *a.* द्वीपीय, द्वीप्य, द्वीपसंबंधिन्. 2 जलपरिगत-परिवृत-वेष्टित.

Insulate, *v. t.* पृथक् कृ 8 U; पृथग् विन्यस् 4 P; *See* **Separate.** **-ed,** *a.* अन्यविभिन्न, पृथक् स्थित, अनन्यसंलग्न-संसक्त. **-ion,** *s.* अन्यवियोगः-विश्लेषः, पृथक् स्थिति *f.*

Insult, *s.* अवमानना, निकृति *f.*, मानभंगः, अवज्ञा; परिभवः-भूति *f.*, अप(व)मानः, तिरस्कारः, परिवादः, दुर्वचस् *n.*, खलोक्ति *f.*; अनादरः, भर्त्सना, धर्षणं, आ-अव-क्षेपः; 'add i. to injury' क्षते क्षारं प्रक्षिप् 6 P. **-v. t.** निकृ 8 U, अव-अप-मन् 4 A or c., अवज्ञा 9 U, तिरस्कृ, परिभू 1 P, आ-अव-धृष् c., निंद् 1 P, गर्ह् 1, 10 A, आ-अधि-क्षिप् 6 P, आक्रुश् c., अप-परि-वद् 1 U, कुत्स् 10 A, लघूकृ. **-ing,** *a.* अपमानकारिन्, अवमानिन्, परिभाविन्, निंदार्थ. **-ingly,** *adv.* सावज्ञं, सावमानं.

Insuperable, *a.* दुरतिक्रम, अलंघ्य, दुस्तर, अनतिक्रमणीय, दुरत्यय, दुरारोह, दुर्जय.

Insupportable, *a.* दुःसह, असह्य, निःसह, दुर्वह, दुर्भर.

Insuppressible, *a.* दुर्निग्रह, दुर्निवार.

Insure, *v. t.* रक्ष् 1 P, प्रति-वि-धा 3 U, सत्यीकृ 1 U, योगक्षेमं कृ or वि-धा, नाशात् निवारू 10. **-ance,** *s.* योगक्षेमः, क्षेमविधानं-करणं, सत्यापनं, रक्षणं.

Insurgent, *s.* राजद्रोहिन् *m.*, राजविरोधिन् *m.*, राजापथ्यकारिन् *m.*, प्रजाविप्लव-प्रकृतिक्षोभ-कारिन् *m.*

Insurmountable, *a. See* **Insuperable.**

Insurrection, *s.* राजविद्रोहः, राज्यप्रकोपः, नृपाभिद्रोहः, प्रकृति or प्रजा-क्षोभः or कोपः, राज्योपप्लवः, उपप्लवः, उपद्रवः. **-ary,** *a.* राज-विरुद्ध-प्रतीप-विपरीत, उपद्रविन्.

Insusceptible, *a.* अग्राहक, अविकारिन्, ग्रहणाक्षम.

Intact, *a.* अखंड, अविकल, अभेद्य.

Intangible, *a.* अस्पृश्य, स्पर्शागोचर, अस्पर्श-वेद्य, दुरालभ.

Integer, *s.* पूर्णांकः, अभिन्नः, रूपं. **-Integrate,** *v. t.* संपूर् 10. **-Integrity,** *s.* अवैकल्यं, साकल्यं, पूर्णता, अभिन्नभावः, अभेदः, अखंडता. **2** शुचिता, आर्जवं, सारल्यं, वैमल्यं; *See* **Honesty;** ' of strict i. ' अभेद्य, अहार्य.

Integral, *s. See* **Integer.**—*a.* पूर्ण, अविकल, समग्र, अभिन्न, अखंड, सांग. **2** पूरित, पूर्ण.

Integument, *s.* वेष्टनं, आ-परि-°; पटलं, कंचुकः, पुटः-टं, कोशः-षः, आच्छादनं, आवरणं.

Intellect, *s.* मतिः, बुद्धिः, प्रज्ञा, धीः, धि(धी)-षणा, मनीषा, प्रेक्षा, शेमुषी, उपलब्धिः, चित्, संविद्, प्रतिपद्, ज्ञप्तिः, चेतना (all *f.*); ' retentive i. ' मेधा, धारणावती-धीः. **-ual,** *a.* Ex. by (*s.*) in comp.; बुद्धि-विषयक, मानसिक (की *f.*); ' i. gain ' ज्ञानोत्कर्षः, मानसोन्नति *f.* **2** बुद्धिमत्, धीमत्, मनीषिन्; ' i. faculty ' धीशक्ति *f.*, निष्क्रमः; ' possessing i. qualities ' धीगुणसंपन्न. **-ually,** *adv.* धिया, बुद्धिपूर्वं.

Intelligence, *s.* मति *f.*, ज्ञानं, बुद्धिचातुर्यं, वैदग्ध्यं, मेधा; *See* **Intellect. 2** वार्ता, उदंतः, वृत्तांतः, प्रवृत्ति *f.*, समाचारः. **3** संदेशः वाचिकं. **-er,** *s.* वार्ताहरः, वार्तावह, संदेशहरः, आख्यायकः, वैवधिकः. **-Intelligent,** *a.* मति-बुद्धि-धी-मत्, प्रज्ञावत्, मेधाविन्, सज्ञान, प्राज्ञ, सुधी. चतुर, कुशल, निपुण, विज्ञ, विदग्ध, निपुणमति. **-ly,** *adv.* चतुरं, स-वैदग्ध्यं, सनैपुण्यं, विज्ञवत्, सुबुद्धिपूर्वं, बुद्धि-चातुर्येण. **-Intelligible,** *a.* स्पष्ट, सुगम, बोधगम्य, भिन्नार्थ, सुबोध, सुव्यक्त, सुग्राह्य, बुद्धिगम्य-ग्राह्य. **-Intelligibly,** *adv.* स्पष्टं, सुव्यक्तं, भिन्नार्थं, स्पष्टार्थं.

Intemperate, *a.* असंयत, असंयमिन्, असं-यमशील, अतिमर्याद, अयतवृत्ति, असंयताचार, असंयतेंद्रिय, अमितभोगिन्; (in eating) अतिभोजिन्, अत्याहारिन्, अयताहार; *See* **Glutton;** (in drinking) अतिपानासक्त, अतिपायिन्, पानप्रसक्त. **2** (Of things) अमित, अपरिमित, अमर्याद, अनियत, अयत, अपरिमाण, उद्रिक्त, अतिरिक्त, अत्यधिक. **-ly,** *adv.* असंयमेन, अमर्यादं, अपरिमितं, अतिशयेन, नियमातिक्रमेण. **-Intemperance,** *s.* असंयमः, अदमः, अनिग्रहः, नियमातिक्रमः, अजितेंद्रियत्वं, अनियतवृत्ति *f.*, अत्याचारः; अतिभोजनं, अत्याहारः, अमिताहारः; अतिपानं, पानप्रसक्ति *f.* **2** उद्रेकः, अमर्यादा, अमितत्वं, आधिक्यं, अनियमः, मर्यादातिक्रमः, अतिशयः, अतिरेकः.

Intend, *v. t.* अभिप्र-इ 2 P, परि-सं-क्लृप् c., इष् 6 P, ईह् 1 A, उद्दिश् 6 P, मनः-मतिं-कृ 8 U, (with dat.), कृ desid. (चिकीर्षति-ते), मनसा चिंत् 10 or उद्दिश्; oft. ex. by desid. forms, or by मनः-काम with inf. form; ' what do you i. to do ' किं कर्तुमनाः. **-Intention,** *s.* अभिप्रायः, संकल्पः आशयः, उद्देशः, इच्छा, कामः, चिकीर्षा, आकांक्षा, आकूतं, बुद्धि-मति-*f.*, भावः, मतं, इंगितं. **2** अर्थः, कार्यं, प्रयोजनं. **3** विवक्षा; ' purity of i. ' भाव-चित्त-शुद्धि *f.*; ' change of i. ' बुद्धिभेदः; ' avowed i. ' प्रकटिताशयः; ' with what i. ' किमु-द्दिश्य, किमभिप्रेत्य, किं फलमपेक्ष्य. **-al,** *a.* मति-बुद्धि-ज्ञान-पूर्व, बुद्धि-संकल्प-कृत, काम्य, कामकृत, सांकल्पिक-ऐच्छिक-(की *f.*). **2** अभिप्रेत, अर्थवत्. **-ally,** *adv.* मति-बुद्धि-ज्ञान-पूर्वं, मतिपुरःसरं, कामतः, ज्ञानतः, बुद्ध्या, साभिप्रायं, मनः-इच्छा-पूर्वकं, यथा-कामं. **-ed,** *a.* Ex. by आशय, बुद्धि, मति in comp.; ' well-i. ' सदाशय; ' evil-i. ' दुराशय, दुष्टमति, पापबुद्धि.

Intense, *a.* प्रचंड, तीव्र, उग्र, तिग्म, प्रखर, अत्यंत, घन, गाढ, प्रबल, तीक्ष्ण, परम, महत्, गुरु, अतिमात्र, भृश, नितांत; gen. by सु or अति pr. **-ify,** *v. t.* वृध् c., प्रकर्षं नी 1 P, better by कृ with (*a.*). **-ity,-ness,** *s.* चंडता, तीव्रता, अत्यंतता, गाढता, प्रकर्षः, उत्कर्षः, गरिमन् *m.*, अतिशयः, उद्रेकः, अति-भूमि *f.*, पराकोटि *f.*-काष्ठा; ' i. of application ' अत्यंताभिनिवेशः, व्यासंगः. **-ive,** *a.* प्रकर्षकर-वृद्धिकर -(री *f.*). **-ly,** *adv.* अत्यंतं, तीव्रं, तीक्ष्णं, नितांतं, अतीव, बलवत्, सु-अति pr.

Intent, *s.* **Intention,** q. v.; ' to all i. s ' सर्वथा. —*a.* एकाग्र, एकनिष्ठ, सुसमाहित, अनन्यमानस, अनन्यविषय, एक-तान-चित्त-अयन; *See* **Fixed;** आसक्तचित्त, आसक्त, व्यापृत, निरत, नियत, व्यग्र, निष्ठित, समाहित, नि-आ-अभिनि-विष्ट, अभियुक्त oft. by पर, तत्पर, निष्ठ, परायण in comp.; ' i. on evil ' दुष्टपरायण; अध्ययनपर, &c. **-ly,** *adv.* एकाग्रचित्तेन, अनन्यमनसा;

एकाग्रतया, निष्ठापूर्वं, साभिनिवेशं, आसक्तचेतसा, मनोयोगेन; 'look or hear i.' लोचनैः or कर्णैः पा 1 P. **-ness**, *s.* एकाग्रता, एकनिष्ठता, अनन्यचित्तता, आसक्ति *f.*, अभिनिवेशः, तत्परता, निष्ठा, मनोयोगः.

Inter, *v. t.* भूमौ-श्मशाने निखन् 1 P or निक्षिप् 6 P or नि-धा 3 U.

Interact, *s.* विष्कंभकः, प्रवेशकः. **-v. t.** मिथः चेष्ट् 1 A or बाध् 1 A.

Intercalar,-y, *a.* अधिक, निवेशित; 'i. month' अधिकमासः, मलमासः, मलिम्लुचः. **-Intercalate**, *v. t.* अधिकमासं-दिवसं निविश् c.

Intercede, *v. i.* अंतर् गम् 1 P or स्था 1 P, मध्ये स्था or गम्, मध्यस्था भू, म-धा 3 U, मध्यस्थतां ग्रह् 9 U, मध्यस्थवृत्तिं आ-स्था 1 U or आश्रि 1 U, माध्यस्थ्यं कृ 8 U (परार्थे) प्रार्थ् 10 A, अनुनी 1 P, आराध् c., वद् 1 P. **-er,-Intercessor**, *s.* मध्यस्थः, मध्यस्थपुरुषः, परार्थं प्रार्थकः, परार्थवादिन् *m.* **-Intercession**, *s.* माध्यस्थ्यं, मध्यस्थता, मधार्न, परार्थप्रार्थनं-ना, पराथ .दिः-निवेदनं.

Intercept, *v. t.* रुध् 7 U, विच्छिद् 7 P, वियुज् 7 A, 10, प्रतिबंध् 9 P; *See* **Obstruct. -er**, *s.* रोधकः, विघ्नकरः. **-ion**, *s.* रोधः, विच्छेदः, प्रतिबंधः, विघ्नः, भंगः.

Interchange, *v. t.* परस्परं विनि-मे 1 A or परिवृत् c., व्यति-ह्र 1 P. **-s.** विनिमयः, परिवर्तः, व्यतिहारः, परिवृत्ति *f.*, आदानप्रदानं; *See* **Exchange. -able**, *a.* परिवर्तनीय, परस्परानुगामिन्.

Interclude, *v. t. See* **Intercept.**

Intercommune, *v. See* **Associate. -ion, -ity**, *s.* अन्योन्यव्यवहारः.

Intercourse, *s.* संगः, समागमः, संगति *f.*, संसर्गः, संगमः, संपर्कः, साहचर्यं, साहित्यं, संघट्टनं, अन्योन्यसंसर्गः, आलापः, संवादः, परिचयः; 'sexual i.' मैथुनं, रतिक्रिया, सुरतं, स्त्रीभोगः; 'social i.' लोकव्यवहारः-संसर्गः.

Intercutaneous, *a.* त्वगंतर्भूत.

Interdependence, *s.* परस्पर-निबंधनं, अन्योन्याश्रयः.

Interdict, *v. t.* नि-प्रति-षिध् 1 P, निवार् 10, प्रत्या-ख्या 2 P, प्रत्या-दिश् 6 P; *See* **Forbid. -s., -ion**, *s.* निषेधः, निवारणं, प्रत्याख्यानं, निरोधः, बाधा. **2** शापः, आक्रोशः. **-ory**, *a.* निषेधक, निवारक.

Interest, *s.* अर्थः, हितं, लाभः, कल्याणं, श्रेयस् *n.*, भूति *f.*, क्षेमः-मं; 'in my i.' मदर्थं-र्थे. **2** आदरः, स्नेहः, रागः, अपेक्षा, अनुरागः, स्पृहा, अपेक्षा. **3** संपातः, संगः; 'without any i.' मुक्त-वीत-संग *a.* **4** वृद्धि *f.*, वार्धुष्यं; 'simple i.' सरलवृद्धिः; 'compound i.' चक्रवृद्धिः; 'i. at five percent' पंचकेन शतेन, पंचकशतं, पंचोत्तरं शतं. **5** भागः, अंशः, अधिकारः, उद्धारः. **6** रसः, विनोदकत्वं, मनोहरता, हृदयंगमता; दृष्टं कथारसस्याक्षेपसामर्थ्यं (Ka. 346) 'you have seen how the i. (i. ing nature) of the story diverted (me) from my topic'; 'take or feel i.' आदृ 6 A; 'looking to one's own i.' स्वार्थबुद्धि *f.*, स्वार्थपरता, स्वार्थलिप्सा. **-v. t.** अनुरंज् c., स्नेहं-अनुरागं-उत्पद् c., अनुरक्त-सानुराग *a.* कृ 8 U. **2** वि-लुभ् c., मनः-चित्तं-रंज् c. or विलुभ् c., हृदयं गम् 1 P or आकृष् 1 P or हृ 1 P, मनो हृ. **3** भागं-अंशं दा 3 U or लभ् 1 A or आप् 5 P; संबंध-अनुबंध-pass. **-ed**, *a.* अनुरक्त, जातानुराग, जातस्नेह. **2** पक्षपातिन्, संगिन्, सपक्षपात. **3** आसक्त, निविष्ट, निरत. **4** भागिन्, अंशिन्. **5** संबद्ध, लाभालाभसंबद्ध. **6** स्वार्थपर, स्वार्थदर्शिन्, स्वलाभासक्त, स्वहितपरायण-तत्पर, स्वलाभापेक्ष, स्वहितैषिन्, स्वार्थलिप्सु. **-ing**, *a.* विनोदिन्, मनोहर, सरस, चित्ताकर्षिन्, हृदयंगम, हृदयहारिन्-ग्राहिन्, विनोदिन्; चित्तरंजक.

Interfere, *v. i.* मध्ये स्था or पत् 1 P, परकार्येषु व्यापृ 6 A, परकार्याणि निरूप् 10 or चर्च् 6 P, 10 A; 'if it should not i. with other duties' न चेदन्यकार्यातिपातः (S. 1); 'he who i. s with matters not his own' अव्यापारेषु व्यापारं यः करोति (P. 1). **2** परस्परं संघट्ट् 1 A or विरुध् 7 U. **-ence**, *s.* माध्यस्थ्यं, परव्यापार-परकार्यचर्चा, परकार्यनिरूपणं; चर्चा, निरूपणं. **2** परस्परसंघट्टः, समाघातः.

Interfluent, *a.* मध्यस्राविन्.

Interfused, *a.* मध्यप्रसारिन्, मध्यप्रसृत.

Interim, *s.* कालाभ्यंतरं, कालांतरालं, मध्य-अंतर्गत-कालः, 'in the i.' अत्रांतरे, कालाभ्यंतरे.

Interior, *a.* अंतरस्थ, अंतर्गत, अंतर्भूत, अंतःस्थ, अंतर्वर्तिन्, आंतर-आभ्यंतर (री *f.*), अंतर् in comp. **-s.** अंतर्भागः, उदरं, गर्भः अभ्यंतरं, हृदयं, अंतर् in comp.; 'the i. of a house' गर्भागारं, वासगृहं, भवनोदरं, अंतर्भवनं.

Interjacent, *a.* मध्यवर्तिन्, मध्यस्थित.

Interject, *v. t.* मध्ये-अंतः-क्षिप् 6 P or प्रविश् c. **-ion**, *s.* अंतःक्षेपः-पणं. **2** उद्गारः.

Interlace, *v. t.* संमिश्र 10, संश्लिष् c.

Interlard, *v. t.* मध्ये-अंतर्-निविश् c. **2** संमिश्र् 10.

Interlay, *v. t.* मध्ये नि-धा 3 U or नि-विश् c.

Interleave, *v. t.* अंतः-मध्ये पत्रं निविश् c.

Interlinear, *a.* पंक्तिद्वयमध्ये लिखित.

Interlocution, *s.* संलापः, संवादः, संकथा, संभाषणं. **-Interlocutor,** *s.* संभाषकः, संवादकः, उत्तरप्रत्युत्तरकृत् *m.* **-y,** *a.* संवाद-संकथा-रूप, संवादात्मक, संकथासंबंधिन्.

Interlope, *v. i.* अन्यायेन (पराधिकारं) प्रविश् 6 P or आक्रम् 1 U, 4 P. **-er,** *s.* अन्यायेन प्रवेशकः, आगंतुकः.

Interlude, *s.* मध्यरंगः; विष्कंभः-भकः.

Interlunar,-y, *a.* अमा, अमावास्या in comp.

Intermarry, *v. i.* परस्परं विवह् 1 P or कुलान् परिग्रह् 9 P or परिणी 1 P. **-age,** *s.* परस्परविवाहः, प्रत्युद्वाहः, विवाहव्यवहारः.

Intermeddle, *v. i.* परकार्याणि निरूप् 10 or चर्च् 6 P, 10 A, पराधिकार-परकार्य-चर्चां कृ 8 U; *See* **Interfere. -er,** *s.* पराधिकारचर्चकः-निरूपकः.

Intermedial, Intermediate, *a.* अंतर्-मध्यवर्तिन्, मध्य, मध्यस्थित, व्यवहित, अंतरालस्थित, अंतर-अंतराल-in comp.; 'i. space' अंतरं, अभ्यंतरं, अंतरालं; 'i. time' कालांतरं. **-ly,** *adv.* मध्ये, अंतराले, अभ्यंतरे.

Interminable, *a.* *See* **Infinite.**

Intermingle, *v. t.* संमिश्र 10, संकॄ 6 P, संसृज् 6 P. संपृच् 2 A, 7 P, संमिल् c.; संकुली-संकीर्णी-कृ 8 U, मिश्रीकृ. **-v. i.** संमिश्रीभू 1 P, संमिल् 6 P. **-ed,** *a.* सं-व्या-मिश्र, मिश्रित, संकीर्ण, संसृष्ट, संपृक्त.

Intermit, *v. i.* विरम् 1 P, निवृत् 1 A (with abl.); शम् 4 P, विच्छिद् pass. **-v. t.** निवृत् c., विरम् c. or शम् c. (रमशमयति), विच्छिद् 7 P, त्यज् 1 P; *See* **Cease. -tent,** *a.* सविराम, सविच्छेद; 'i. fever' मुक्तानुबंधी ज्वरः. **-Intermission,** *s.* विरामः, विरति *f.*, निवृत्ति *f.*, विच्छेदः; उपशमः; 'without i.' निरंतरं, अनवरतं, अविरतं, अविच्छेदं. **-Intermissive,** *a.* *See* **Internittert,** above.

Intermix, *v. t.* *See* **Intermingle. -ture,** *s.* संसर्गः, संमिश्रणं, संकरः, संपर्कः, संयोगः, संमिलनं.

Intermontane, *a.* पर्वतमध्यवर्तिन्.

Intermundane, *a.* जगन्मध्यवर्तिन्.

Intermural, *a.* प्राकारांतवर्तिन्.

Internal, *a.* अंतर् in comp.; अंतर्गत, अंतःस्थ, आभ्यंतर-आंतर (री *f.*), गर्भस्थ; 'i. soul' अंतरात्मा; 'i. anguish' अंतःशोकः, अंतर्दाहः; *See* **Inside. -ly,** *adv.* अंतर्, अंतरे, अभ्यंतरे.

International, *a.* (देशानां) परस्परव्यवहारसंबंधिन्.

Internecine, *a.* परस्परविनाशिन्, मिथःक्षयकर, प्राणापहारिन्.

Interpolate, *v. t.* सकपटं नि-विश् c. or निक्षिप् 6 P, मिथ्या क्लृप् c. or अभिलिख् 6 P. **-ion,** *s.* कपटेन निवेशनं, मिथ्याकल्पनं; मिथ्याकल्पितं, निवेशितलेखः.

Interpose, *v. t.* मध्ये निक्षिप् 6 P, अंतर्-धा 3 U, व्यव-धा, मध्ये-अंतः-स्था c. (स्थापयति) or नि-प्र-विश् c. **-v. i.** मध्ये स्था 1 P or वृत् 1 A or गम् or पत् 1 P, अंतर्-इ 2 P, मध्ये प्रविश् 6 P; मध्यस्थतां ग्रह् 9 U, माध्यस्थ्यं अवलंब् 1 A. **-er,** *s.* मध्यस्थः, मध्यवर्तिन् *m.*, मध्यस्थायिन् *m.* **-ition,** *s.* मध्यस्थता, माध्यस्थ्यं; व्यवधानं, मध्यवर्तित्वं, अंतरायः.

Interpret, *v. t.* युज् 10 (words, &c.); व्याख्या 2 P, वि-वृ 5 U, व्याचक्ष् 2 A, अर्थं प्रकाश् c. or व्या-ख्या or वि-वृ or व्याकृ 8 U; *See* **Construe, Explain. 2** भाषांतरेण वद् 1 P or कथ् 10 or व्याहृ 1 P. **-ation,** *s.* (पदानां) योजना; व्याख्या, व्याख्यानं, विवरणं, निरूपणं, अर्थ-बोधनं-प्रकाशनं, विचारः; 'i. of a dream' स्वप्नार्थः, स्वप्न-विचारः-निरूपणं. **2** अर्थः, व्याख्या, टीका, भाष्यं. **3** भाषांतरं. **-er,** *s.* व्याख्यातृ *m.*, विवरणकृत् *m.*, अर्थ-प्रकाशकः-बोधकः, **2** भाषाद्वयज्ञः भाष्य-वृत्ति-कारः, टीकाकृत् *m.*

Interregnum, *s.* अराजत्वं, अनायका-अराजका-राज्यस्थिति.

Interrogate, *v. t.* प्रच्छ् 6 P, अनुयुज् 7 A, परीक्ष् 1 A. **-ion,** *s.* पृच्छा, प्रश्नः, अनुयोगः. **-ive,** *a.* प्रश्नरूप, प्रश्नार्थक प्रश्नात्मक. **-ively,** *adv.* प्रश्न-रूपेण-क्रमेण, अनुयोगतः, प्रश्नार्थरूपेण. **-or,** *s.* प्रष्टृ *m.*, पृच्छकः, अनुयोक्तृ *m.* **-ory,** *s.* प्रश्नः, अनुयोगः. **-a.** *See* **Interrogative above.**

Interrupt, *v. t.* प्रति-... 9 P, प्रति-वि-हन् 2 P, उप-नि-रुध् 7 U, भंज् 7 P, विच्छिद् 7 P, खंड् 10, बाध् 1 A, भिद् 7 P, विघ्नयति (D.); (speech &c.) आक्षिप् 6 P; 'do not i. him' मैनमंतरा प्रतिबध्नीत (S. 6). **-ion,** *s.* अंतरायः, प्रतिबंधः, उपरोधः, विच्छेदः, भंगः, भेदः. व्याघातः, विघ्नः; 'i. in sleep' निद्राभंगः. **-edly,** *adv.* सविच्छेदं, सभंगं. **-er,** *s.* विच्छेद-भंग-कारिन् *m.*, विघ्न-व्याघात-कृत् *m.*

Intersect, *v. t.* परस्परं-अंतरा-छिद् 7 P. **-ion,** *s.* परस्परच्छेदः.

Intersperse, *v. t.* इतस्ततः प्र-क्षिप् 6 P or सं-समा-कॄ 6 P or संमिश्र् 10. **-ed,** *a.* संमिश्र, संकीर्ण. **-ion,** *s.* संमिश्रणं, वि-संकिरणं.

Interstellar, *a.* तारागणमध्यवर्तिन्.

Interstice, *s.* छिद्रं, रंध्रं, संधिः, विच्छेदः, अंतरं, अंतरालः-लं, अवकाशः, विवरं; 'without i. s' निरंतर, नीरंध्र, निश्छिद्र, निबिड, घन, अविरल; 'having i. s' सच्छिद्र, सांतराल, विरल.

Intertexture, *s.* संग्रथनं, परस्परस्यूति *f.*

Intertwine, Intertwist, *v. t.* ग्रंथ् 9 P, सं-उह्°, परस्परं कुंच् c. or व्यावृत् c., उत्क्षच् 10, परस्परं ग्रंथ् or संयुज् 7 U, 10, समिश्र् 10; 'with hair i. ed with the tendrils of creepers' लताप्रतानोद्ग्रथितैः केशैः (R. II. 8); अनुव्यध् 4 P, सं-वे 1 U; शैवलेनानुविद्धं (सरसिजं) (S. 1) 'i. ed with moss.'

Interval, *s.* अंतरं, अंतरालं, अभ्यंतरं; अवकाशः, मध्यस्थानं, व्यवधानं, व्यवायः. 2 अवधिः, मध्य-अभ्यंतर-कालः, अवकाशः. 3 विरामः, विच्छेदः, निवृत्ति *f.*, उपशमः; 'in the i.' अंतराले, अंतरा; 'at i. s' काले काले, अंतरा अंतरा, (प्रजानुरागहेतोश्चांतरांतरा दर्शनं ददौ Ka. 58); रम्यांतरः कमलिनीहरितैः सरोभिः (S. 4) 'pleasant at i. s &c.'; 'without i. s' निरंतर, निरंतराल.

Intervene, *v. i.* मध्ये-अंतर् गम् 1 P or भू 1 P or स्था 1 P or वृत् 1 A, अंतर्धा 2 P or उप-स्था. 2 अंतर्-इ 2 P, व्यव-धा pass. **-ing,** *a.* मध्यवर्तिन्, मध्यस्थायिन्, व्यवहित, अंतरित, अंतरागत, मध्ये स्थित; 'i. period' अंतरालं, अभ्यंतरकालः. **-Intervention,** *s.* मध्यस्थता, माध्यस्थ्यं, व्यवधानं, अंतर्गमनं, मध्यवर्तनं, मध्ये स्थिति *f.*

Interview, *s.* दर्शनं; सन्निपातः, संगमः, समागमः, अन्योन्य-परस्पर-दर्शनं; 'he had an i. with the king' स नृपदर्शनं लेभे, राजदर्शनं कारितः.

Interweave, *v. t. See* **Intertwine.**

Intestate, *a.* अकृतमृत्युलेख.

Intestine, *a.* अबाह्य; *See* **Internal. 2** अविदेशज, देशीय; गृह in comp.; 'i. quarrels' गृह-च्छिद्रं-भेदः, अंतर्भेदः. **-s.** अंत्रं, पुरीतत् *n.*; नाडि-कोष्ठ-...*f.*

Intimate, *a.* गाढ, रूढ, प्रवि-रूढ, दृढ, दृढबद्ध, घन. 2 (Of persons) सुपरिचित, रूढसौहृद, बद्धसख्य, प्रणयिन्, प्रियतम, हृदयंगम, सुसंसर्गिन्, संस्तुत, दृढ-गाढ-सौहृद. 3 **Internal,** q. v.; 'strangers made i.' बाह्या अभ्यंतरीकृताः (P. I. 9). **-s.** दृढसुहृद् *m.*, दृढमित्रं, सुहृत्तमः, प्रियवयस्यः. **-v. t.** (भंग्या) सूच् 10, संदिश् 6 P, उपन्यस् 4 U, उपक्षिप् 6 P; साकूतं कथ् 10. **-ion,** *s.* सूचना, संदेशः, उपक्षेपः; इंगितं, आकूतं. **-ly,** *adv.* दृढं, गाढं; दृढ-सौहृदेन-संसर्गेण, सुपरिचितं, दृढमित्रवत्; दृढ, गाढ in comp. **-Intimacy,** *s.* गाढसौहृदं, सुपरिचयः, दृढसंसर्गः-संयोगः, संस्तवः, अतिमित्रता-प्रणयः-सख्यं, अत्यासंगः, अतिपरिचयः.

Intimidate, *v. t.* त्रस् c., भी c. (भीषयते-भापयते), सभयं निवृत् c. 2 भर्त्स् 10 A, तर्ज् 1 P, 10 A. 3 **Dishearten,** q. v. **-ion,** *s.* भीषका, भीषा, भीषणं, भयप्रदर्शनं; भर्त्सनं, तर्जनं.

Into, *prep.* मध्ये, अंतर्, अंतरे; gen. by loc., or by acc. with verbs of motion; 'converted i. water' जलसात्कृत; 'made i. one mass' एकपिंडीकृत-भूत.

Intolerable, *a.* असह्य, असहनीय, दुःसह, अक्षंतव्य, दुर्विषह.

Intolerant, *a.* अक्षमिन्, असहन, अमर्षण, असहिष्णु, अक्षम. 2 परमतासहिष्णु, परमतादूषक, अन्यमतासह. **-Intolerance,** *s.* अमर्षणं, अतितिक्षा, अक्षमा, असहिष्णुता.

Intone, *v. t.* गंभीरं वद् 1 P or वच् 2 P, गंभीरस्वनं उद्घुष् c. or उद्गाह् 1 P. **-ation,** *s.* स्वरः, लयः, वर्णोच्चारणं; स्वरभेदः.

Intort, *v. t. See* **Contort.**

Intoxicate, *v. t.* मद् c., उद्-प्र-°, मदं उत्पद् c., मत्तीकृ 8 U; (fig.) उत्सिच् c., उद्हन् 2 P, आ-ध्मा 1 P, मुह् c. **-ed,** *a.* मत्त, प्र-उत्-मत्त, क्षीब, मदोन्मत्त, उन्मद, मदोद्धत, मदान्वित, शौंड, मदोद्धत; 'to be i.' मद् 4 P, मदेन मुह् pass., क्षीब् 1, 4 P. **-ing,** *a.* उन्मादक, मादक, उन्मादिन्. **-ion,** *s.* मदः, मादः, उन्मादः, क्षीवता, शौंडता, मत्तता.

Intractable, *a.* दुर्दम, दुर्दांत, अदम्य, अविधेय, अवश्य, अविनेय, दुर्निग्रह, दुराधर्ष, दुःशास्य, अनिवार्य, प्रतीप, उच्छृंखल.

Intramural, *a.* प्राकारांतर्वर्तिन्, भित्त्यंतर्वर्तिन्.

Intransient, *a.* अभंगुर, चिरस्थायिन्.

Intransitive, *a.* अकर्मक.

Intrench, *v. t.* परिखया रक्ष् 1 P or परिवेष्ट् c. or परि वृ 5 U, परिखां खन् 1 P. 2 आक्रम् 1 U, 4 P. **-ment,** *s.* परिखा, परिक्रिया.

Intrepid, *a.* निर्भय, निःशंक, शूर, साहसशील, प्रगल्भ. **-ity,** *s.* धैर्य, प्रतिभा, प्रतिभानं, शौर्य, निर्भयत्वं, पौरुषं, विक्रमः. **-ly,** *adv.* वीरवत्, सविक्रमं, समतिभं; *See* **Bold,-ly,** &c.

Intricate, *a.* विषम, दुर्गाह्य, संकुल, गहन, दुर्बोध, गूढ, अस्पष्टार्थ. 2 वक्र, असरल, जिह्म, कुटिल. **-ly,** *adv.* विषमं, असरलं, कुटिलं. **-ness, -Intricacy,** *s.* वैषम्यं, गहनता, गूढता. 2 वक्रता, कौटिल्यं, असारल्यं.

Intrigue, *s.* उपजापः, कूटप्रबंधः, कपटप्रबंधः, कूटयुक्ति *f.*, कूट or कपट-संकल्पः or प्रयोगः; 'love-i.' व्यभिचारकर्मन् *n.*, कामचारितं. **-v. i.** उपजप् 1 P, उपजापं रच् 10, कूटप्रबंधं प्रयुज् A, 10, कूटप्रयोगं रच्. **-er,** *s.* उपजापकः, कपट-प्रबंधयोजकः.

Intrinsic,-al, *a.* अंतरस्थ, अंतर्गत, सहजवर्तिन्, स्वभावज, आंतर-आभ्यंतर (री *f.*). 2 सत्य, यथार्थ, वास्तविक (की *f.*), अकृत्रिम, स्वाभाविक-सांसिद्धिक-(की *f*). **-ally,** *adv.* वस्तुतः, तत्त्वतः, यथार्थतः, स्वभावतः.

Introduce, *v. t.* प्रविश् c., दर्शनं कृ c. 2 (Insert) प्र-नि-आ-विश् c. 3 परिचयं उत्पद् c. or जन् c. (जनयति); 'i. me to your friend' तव मित्रेण मम परिचयमुत्पादय. 4 प्रवृत् c., प्रचर्-ल् c., प्रति-ष्ठा c. (-ष्ठापयति), प्रारभ् 1 A, प्रस्तु 2 U, उपक्रम् 1 A. 5 आ-नी 1 P, आवह् 1 P, आगम् c. (गमयति). **-er,** *s.* प्रवेशकः. 2 प्रवर्तकः, प्रतिष्ठापकः, प्रारंभकः. **-Introduction,** *s.* प्रवेशनं; परिचयकरणं. 2 प्रवर्तनं, प्रचारणं, प्रतिष्ठापनं, निवेशनं; आनयनं. 3 मुखबंधः, आमुखं, प्रस्तावना (of plays); प्रस्तावः, आरंभः, उपन्यासः, वाङ्मुखं, उपोद्घातः, उदाहारः, उपक्रमः, वचनारंभः. **-Introductory, -Introductive,** *a.* प्रावेशिक (की *f.*), आरंभक, प्राथमिक (की *f.*), प्रथम; उपोद्घात or प्रस्तावना in comp.; 'as an i. portion' उपोद्घातरूपेण, प्रस्तावनाद्वारा. 2 प्रस्तावना रूप; पारिभाषिक (की *f.*).

Intromit, *v. t.* प्रविश् c.

Introspection, *s.* अंतर्दर्शनं, अंतरालोकनं.

Introvert, *v. t.* अंतः परिवृत् c.

Intrude, *v. i.* अनाहूत-*a* प्र-आ-विश् 6 P or आगम् 1 P, सधर्षं प्रविश् or आक्रम् 1 U, 4 P, अनधिकारपूर्वं प्रविश्. **-er,** *s.* आगंतुकः, अनाहूत प्रवेशकः. **-Intrusion,** *s.* आगंतुकभावः, अनाहूत प्रवेशः-शनं. **-Intrusive,** *a.* धृष्ट, आगंतुक, प्रगल्भ, सधर्ष; परचर्चाशील.

Intrust, *See* **Entrust.**

Intuition, *s.* सहजावबोधः, सहजज्ञानं, अंतर्ज्ञानं. **-Intuitive,** *s.* सहजोपलब्ध, अंतर्ज्ञानोपलभ्य, अविचारपूर्वं उपलब्ध. 2 सहजज्ञ, अंतर्ज्ञानिन्. **-ly,** *adv.* सहजज्ञानेन; अंतर्ज्ञानेन, प्रमाणनिरपेक्षं.

Intumesce, *v. i.* श्वि 1 P; *See* **Swell.** **-ence,** *s.* शोथः, शोफः.

Inturbidate, *v. t.* कलुषीकृ 8 U, आविलयति (D.); *See* **Confuse.**

Intwine, Intwist, *v. t.* ग्रंथ् 9 P, गु(गुं)-फ् 6 P, रच् 10; *See* **Intertwine.**

Inumbrate, *v. t.* छायया आ-प्र-च्छद् 10.

Inunction, *s.* अभ्यंजनं, विलेपनं.

Inundate, *v. t.* जलेन आप्लु c. or व्याप् 5 P. **-ed,** *a.* आप्लावित, आ-सं-प्लुत, जलाप्लावित, जलव्याप्त, जलमय (यी *f.*). **-ion,** *s.* आप्लावः, जलौघः, तोय or जल-विप्लवः-प्रलयः-उप-प्लवः, जलवृद्धि *f.*; *See* **Deluge.**

Inurbanity, *s.* अशिष्टता, असभ्यता.

Inure, *v. t.* अभ्यस् 4 U or c., शिक्ष् c., परिचयं कृ 8 U; परिचित-*a.* कृ. 2 कठिनीदृढी-कृ. **-ed,** *a.* अभ्यस्त, ज्ञात, परिचित; अभिज्ञ in comp.; 'i. to fatigue' जितश्रम; 'i. to seclusion' परिचितविविक्त.

Inurn, *v. t.* समाधौ नि-धा 3 U or निक्षिप् 6 P.

Inutility, *s.* अनुपयोगः, वैफल्यं, व्यर्थता, मोघता, वैयर्थ्यं.

Invade, *v. t.* अभि-द्रु 1 P, आक्रम् 1 U, 4 P, अवस्कंद् 1 P, अभिप्र-या 2 P, आपत् 1 P, उप-द्रु 1 A. or c.; *See* **Attack.** **-er,** *s.* आक्रामकः, उपप्लविन् *m.*; gen. ex. by **Enemy,** q. v. **-Invasion,** *s.* आक्रमः-मणं, अवस्कंदः, अभिद्रवः, उपप्लवः, अभिप्रयाणं, अभियोगः, आपातः.

Invalid, *a.* दुर्बल, अशक्त, अप्रभाव, निस्तेजस्, व्यर्थ, विफल. 2 अप्रमाण; निष्प्रमाण, लघुप्रमाण. **-s.** रोगिन् *m.*, रुग्णः, आतुरः. **-ate,** *v. t.* मोघी-व्यर्थी-कृ 8 U, विफलीकृ, लुप् 6 P or c., अधरीकृ. **-ity,** *s.* निर्बलता, अनिष्पत्ति *f.*, व्यर्थता, मोघता. 2 अप्रामाण्यं.

Invaluable, *a.* अनर्घ, अनर्घ्य, अमूल्य, मूल्यातीत, अतिमूल्य, अत्युत्कृष्ट.

Invariable, *a.* नित्य, सतत, अविकार्य, निर्विकार, स्थिर, नियत, अचल, एकांत; नायमेकांतो नियमः (S. B. 273) 'not an i. rule.' **-y,** *adv.* एकांततः, नित्यं, नियतं.

Invective, *s.* आ-अधि-क्षेपः, निर्भर्त्सना, निंदा, निंदावाक्यं, दुरुक्ति *f.*, अप-परि-वादः, गर्हा. **-a.** निंदक, अपवादक, निंदात्मक.

Inveigh, (against) *v. i.* आ-अव-अधि-क्षिप् 6 P, निंद् 1 P, गर्ह् 1, 10 A, अभिशंस् 1 P; *See* **Abuse, Censure.**

Inveigle, *v. t.* प्र-वि-लुभ् c., मुह् c., चाटूक्त्या आकृष् 1 P or प्रलुभ् c. or निपत् c., वंच् 10. **-er,** *s.* प्र-वि-लोभकः, मोहकः, आकर्षकः. **-ing, -ment,** *s.* प्र-वि-लोभनं; आकर्षणं, मोहः, वंचना, प्रतारणा.

Invent, *v. t.* क्लृप् c., निर्मा 3 A, 2 P, सृज् 6 P, वि-धा 3 U, घट् c. (घटयति), रच् 10. 2 मनसा सृज् 10 or चिंत् 10 or क्लृप् c. 3 मिथ्या क्लृप् c. **-ed,** *a.* कॢप्त, निर्मित, रचित, घटित. 2 मनःसृष्ट, मनःकल्पित, मिथ्याकल्पित, काल्पनिक (की *f.*), कृतक, कृत्रिम. **-ion,** *s.* कल्पना-नं, रचना-नं, निर्माणं, घटनं. 2 कृति *f.*, सृष्टि *f.*, कल्पितं, कल्पना, निर्मितकला. 3 कल्पना, युक्ति *f.*, उपायज्ञानं. 4 मिथ्याकल्पनं, कूटरचना, मनःसृष्टिः; 'one's own i.' स्वकपोलकल्पितं. **-ive,** *a.* कल्पक, योजक, उपायज्ञ, कल्पनाचतुर, निर्माणकुशल, चतुर, युक्तिमत्. **-or,** *s.* कल्पकः, स्रष्टृ *m.*, निर्मातृ *m.*, चिंतकः, योजकः.

Inventory, *s.* (गृहोपस्करादेः) परिसंख्या, परिगणना, संख्यापत्रं.

Inverse, *a.* व्यत्यस्त, विपर्यस्त, व्यस्त, पर्यस्त, विपरीत, वि-प्रति-लोम, प्रतीप, व्युत्क्रांत. **-ly,** *adv.* विपर्ययेण, वि-प्रति-लोमतः, व्यत्यासेन, व्युत्क्रमेण. **-Inversion,** *s.* विपर्यासः, विपर्य-

(र्या)पः, व्युत्क्रमः, व्यत्यासः, पर्यासः, प्रातिलोम्यं, व्यत्ययः; व्यस्तता, विपरीतता.

Invert, *v. t.* विपर्यस् 4 U or c., परि-वि-व्यति-अस्, परिवृत् c., विपर्यासं-विपर्ययं-नी 1 P; *See* **Alter, Change. 2** अधोमुखीकृ 8 U; विलोमीकृ. **-ed,** *See* **Inverse.**

Invertebrate, *a.* पृष्ठवंशहीन. **2** (fig.) संशयात्मन्, अधीर, चंचलमति.

Invest, *v. t.* परि-धा c. (धापयति), आच्छद् 10, प्रावृ 5 U, संवेष्ट् c., वस् c., संव्ये 1 P. **2** अलंकृ 8 U, मंड् 10, भूष् 10. **3** संयुज् 7 U, 10, संपन्न-युक्त-विशिष्ट-*a.* कृ; *See* **Endow. 4** उपरुध् 7 U, पर्यवस्कंध् 9 P. **5** (Money) लाभार्थं विनियुज् 7 A, 10; 'i. with power' अधिकारे प्रविश् c. or नियुज्; प्रति-ष्ठा c. (-ष्ठापयति), संस्कृ, अभिषिच् 6 P. **-iture,** *s.* अभिषेकः, संस्कारः, प्रतिष्ठापनं, पदस्थापनं, अधिकारदानं; 'i. with the sacred thread' उपनयः-यनं. **-ment,** *s.* परिधानं, वस्त्रं. **2** उपरोधः, अवष्टंभः. **3** लाभार्थं धनविनियोगः.

Investigate, *v. t.* अव-परि-सं-ईक्ष् 1 A, निरूप् 10, अनुसं-धा 3 U, विचर् c., विमृश् 6 P, निर्णी 1 P, निश्चि 5 U, निधृ 10, आलोच् 10. **2** अन्विष् 4 P, मृग् 10 A.; *See* **Examine. -ion,** *s.* अवेक्षणं, निरूपणं, अनुसंधानं, विचारः-रणा-णं, विमर्शः, निर्णयः, निश्चयः; चर्चा, अन्वेषणं, अनुयोगः, जिज्ञासा; 'under i.' निरूप्यमाण. **-or,** *s.* अवेक्षकः, निरूपकः, विचारकः, अनुसंधातृ *m.*, निर्णेतृ *m.*

Inveterate, *a.* बद्ध-रूढ-मूल, सुदृढ, गाढ, प्ररूढ, दृढ, स्थिर, चिर-बहु-कालिक (की *f.*), चिरस्थायिन्; 'i. enemy' गाढ-बद्ध-वैरः शत्रुः; 'i. enmity' बद्धवैरं. **-Inveteracy.** *s.* बद्धवैरं, वैरानुबंधः; बद्धमूलता, विरूढता, स्थिरता, अभिनिविष्टता.

Invidious, *a.* द्वेषजनन (नी *f.*), मत्सरावह, ईर्ष्या-असूया-कर (री *f.*). **2** मत्सरिन्, समत्सर, ईर्ष्यालु. **-ly,** *adv.* समत्सरं, साभ्यसूयं, सेर्ष्यं.

Invigorate, *v. t.* बलं-तेजः-शक्तिं वृध् c. or धा 3 U or उप-चि 5 U, आप्यै c., पुष् 1, 9 P, or c.; दीप् c. **-ing,** *a.* बलवर्धन (नी *f.*), तेजस्कर (री *f.*), पुष्टिद, वीर्यप्रद, उत्साहदायिन्. **-ion,** *s.* बल-तेजो-वर्धनं, पुष्टिकरणं. **2** बल-तेजो-वृद्धि *f.*

Invincible, *a.* अजय्य, दुर्जय, दुरासद, अधृष्य, अवृष्य.

Inviolable, *a.* अलंघ्य, अनतिक्रमणीय, अभेद्य, मर्यादोचित. **2** अवध्य, अनपकार्य, अवध्य (as a herald). **-ness,** *s.* अलंघ्यता, अवध्यभावः

Inviolate, *a.* अभिन्न, अभग्न, अलंघित, अक्षत, अदूषित, अखंड, अभंग.

Invisible, *a.* अदृश्य, परोक्ष, दुर्दर्श, अंतर्हित, तिरोहित, अंतरित, दृष्टिपातातीत, नयनविषयातीत, दृग्गोचर,दृष्टअविषय, अलक्ष्य, अचाक्षुष (षी *f.*) ('evidence &c.); 'to be i.' अंतर्-तिरः-धा pass., तिरोभू 1 P, अंतर्-इ 2 P. **-ness,** *s.* परोक्षता, अप्रत्यक्षता, अदर्शनं, तिरोधानं, अंतर्धानं, अविषयः, परोक्षं. **-y,** *adv.* अप्रत्यक्षं, परोक्षं, असमक्षं अलक्ष्यं, असाक्षात्, अदृष्टरूपेण; निभृतं अलक्षितं.

Invite, *v. t.* आ-नि-अभि-मंत्र् 10 A, आ-समा-ह्वे 1 P, अभ्यर्थ् 10 A, आकृ c., आवह् c. **2** आकृष् 1 P, हृ 1 P, प्र-वि लुभ् c. **-ation,** *s.* निमंत्रणं, आह्वानं, आवाहनं, अभ्यर्थना. **-ing,** *a.* चित्ताकर्षिन्, मोहिन्, मनोहर.

Invocate, *See* **Invoke.**

Invoice, *s.* आवाहपत्रं, बीजकं.

Invoke, *v. t.* आ-ह्वे 1 P, आ-अभि-मंत्र् 10 A, आ-वद् 1 P, संबुध् c., आवह् c., आकृ c., नाम ग्रह् 9 U or स्मृ 1 P; अर्थ् 10 A, अभिवंद् 1 A; 'i. blessings on' आशास् 2 A. **-Invocation,** *s.* आह्वानं, आमंत्रणं, आवाहनं, नामग्रहणं, प्रार्थनं-ना.

Involuntary, *a.* अकाम्य,अनिच्छापूर्व,अबुद्धि-अज्ञान-पूर्व, अनैच्छिक (की *f.*), अस्वेच्छाजात. **2** अकाम, अनिच्छु. **-ly,** *adv.* अकामतः अकाम- अनिच्छा-अमति-पूर्वं, अनिच्छया, असंतोषेण, अबोध-अज्ञान-पूर्वं.

Involve, *v. t.* अवगुंठ् 10, आवृ 5 U, आ-वेष्ट् 1 A, or c., आच्छद् 10. **2** परिग्रह् 9 P, अंतर्गण् 10, समाविश् c., *See* **Include. 3** अभिभू 1 P, ग्रस् 1 A; 'i. ed in difficulty' विपद्ग्रस्त. **4** संबंध् 9 P, संश्लिष् c., संयुज् 7 U, 10, संसञ्ज् 6 P, लिप् 6 P, संक्रम् c.; *See* **Implicate. -ed,** *a.* आवेष्टित, अवगुंठित, आवृत, आच्छन्न. **2** अंतर्गत, परिगृहीत, समाविष्ट, अंतर्भूत, गर्भ in comp. **3** अभिभूत, ग्रस्त. **4** संबद्ध, संश्लिष्ट, संसृष्ट, संसक्त, अनुषक्त, संयुक्त, लिप्त; 'i. in crimes' पापलिप्त, दोषग्रस्त. **5** ध्वनित, फलित; 'i. meaning' फलितं, फलितार्थः, ध्वनिः. **-Involution,** *s.* आवेष्टनं, आवरणं. **2** जटिलत्वं, व्यतिकरः, संकीर्णता, अन्योन्यसंश्लेषः, परस्परसंसक्ति *f.* **3** (In Math.) संवर्गीकरणं; 'i. to the third power' सदृशत्रयसंवर्गः.

Invulnerable, *a.* अभेद्य, अच्छेद्य, क्षतःक्षम.

Inward, *a.* अंतर्वर्तिन्, अंतःस्थित, अंतरस्थ, अंतर्भव; oft. by अंतर् in comp. **-*adv.*, -ly,** *adv.* अंतः, अभ्यंतरं; 'i. corrupted' अंतर्दुष्ट. **2** मनसा, चित्तेन, हृदये; सुनिभृतं. **-Inwards,** *s.* अंत्राणि (pl.).

Inweave, *v. t.* *See* **Intertwine.**

Inwrap, *v. t.* आवेष्ट् 1 A or c.; *See* **Involve** (1).

Inwrought, *a.* खचित, प्रणिहित, प्रतिबद्ध, छुरित.

Iota, *s.* अणुः, लवः, कणः, कणिका, बिंदुमात्रं.

Irascible, *a.* चंडकोप, क्रोधशील, सुलभकोप, शीघ्रकोपिन्, क्रोधिल, संरंभिन्, चंडस्वभाव. **-ness,** *s.* क्रोधशीलता, सुलभकोपः, चंडता, पित्तस्वभावः-प्रकृति *f.*

Irate, *a.* क्रुद्ध, कुपित, रुष्ट.

Ire, *s.* रोषः, क्रोधः, कोपः. **-ful,** *a.* क्रुद्ध, रुष्ट; *See* **Angry.**

Iris, *s.* इन्द्रधनुस् *n.* 2 तारामंडलं. 3 गोलोमी, श्वेतदूर्वा.

Irk, *v. t.* पीड् 10, आयस् c., खिद् c.; *See* **Afflict. -some,** *a.* दुःख-खेद कर (री *f.*), दुःखद, क्लेशावह, क्लेशद, आयासहेतुक, कष्ट; 'how i. are the toils of state ! राज्यं हि नाम (राज्यशासनश्रमाः) महदप्रीतिस्थानं (Mu. 3).

Iron, *s.* लोहः-हं, अयस् *n.* आयसं, कालायसं, कृष्णायसं, पिंडं, तीक्ष्णं, शस्त्रकं, अश्मसारः, लौहं; 'green sulphate of i.' धातुशेखरं, कासी(शी)सं; 'rust of i.' मंडूरं, सिंहाणं, अयोमलं, 'tipped with i.' आयोग्र, लोहाग्र; 'sulphuret of i.' ताप्यं; 'wrought i.' कुशी. 2 बंधनं, शृंखला-लः-लं, लोहबंधनं. **-v. t.** शृंखलया बंध् 9 P, or संयम् 1 P. **-a.** लौह (ही *f.*), लोहमय-अयोमय (यी *f.*), लोहनिर्मित, आयस (सी *f.*), लोहात्मक, लोह or अयस् in comp.; 'of an i. constitution' वज्रदेह, सिंहसंहनन; 'i.-bar' फालः, लोहपिंडः; 'i.-filings' लोहचूर्णं, लोहजं; 'i.-fisted' लोह-वज्र-मुष्टि; 'i.-foundery' संधानी, कुप्यशाला; 'i.-hearted' अयो-वज्र-हृदय, कठिन-पाषाण-हृदय; 'i.-mold' लोहांकः, लोहचिह्नं; 'i.-monger' लोहकारः, अयस्कारः, अयोकारः, लोहकारकः. **-y,** *a.* *See* (*a.*) above.

Irony, *s.* सोल्लुंठः-ठनं, सोत्प्रासः, व्याजस्तुति *f.*, निंदा, व्याजोक्ति *f.*, विपरीतलक्षणा, उपरोधः; 'it was a strange i. of fate in the case of Râma' रामस्यापि दैवदुर्नियोगः कोपि यत् &c. (U. 4). **-ical,** *a.* (*s.*) in comp.; 'i. speech' सोल्लुंठवचनं, सोल्लुंठनोक्तिः; 'i. speaker' सोल्लुंठवादिन् *m.* **-ically,** *adv.* सोत्प्रासं, सोल्लुंठनेन, व्याजोक्त्या.

Irradiate, *v. t.* प्रकाश् c., द्युत् c., दीप् c., राज् c. **-ion,** *s.* प्रकाशनं, द्योतनं, प्रदीपनं. 2 (Irradiance) उद्द्योतः, दीप्ति *f.*, प्रभा, कांति-द्युति *f.*, तेजस् *n.*

Irrational, *a.* विवेक-रहित-वर्जित-हीन, अचेतन, अविवेक, ज्ञान-बुद्धि-हीन, निर्बोध, अव्युत्पन्न, विचारशक्तिरहित; पशुधर्मन्. 2 न्याययुक्ति-विरुद्ध, अन्याय्य, अयुक्तिसिद्ध, अतार्किक (की *f.*). **-ity,** *s.* बुद्धिहीनता, अन्याय्यता. **-ly,** *adv.* न्यायविरोधेन, अयुक्तिवादेन.

Irreconcilable, *a.* असंधेय, अशाम्य. 2 असंगत, विगीत, परस्परविरुद्ध, परस्परपराहत; *See* **Inconsistent. -ness,** *s.* असंगति *f.*, परस्परविरोधः.

Irrecoverable, *a.* अपुनःप्राप्य, पुनरलभ्य, असमाहार्य. **-y,** *adv.* अनुद्धार्यतया; 'it is i. gone' असन्निवृत्त्यै तदतीतमेव (S. 6).

Irredeemable, *a.* अनिष्क्रेय, अत्यंतनष्ट.

Irreducible, *a.* न्यूनीकरणाक्षम.

Irrefragable, *a.* अखंडनीय, अबाध्य, अप्रत्याख्येय, दृढ-स्थिर-प्रमाण.

Irrefutable, *a.* अप्रत्याख्येय, अखंडनीय.

Irregular, *a.* अनियत, विधि-नियम-विरुद्ध, अयथाविधि, अविधि, उत्सूत्र, विधिघ्न (घ्नी *f.*); (as words) अपवादक, निपातित; 'these are put down as i. forms' एते निपात्यंते (S. K.). 2 क्रम-हीन-रहित-शून्य-विरुद्ध, अव्यवस्थित, अपर्याय, उच्छृंखल. 3 (In conduct) उत्क्रांतमर्याद, व्यभिचारिन्, विपथ-अपथ-गामिन्, दुराचार, कुचारिन्, अमर्याद. 4 विषम, असम; 'i. in shape' विरूप, कदाकार. **-ity,** *s.* अविधिः, विधि or नियम-विरोधः or भंगः, अनियमः, उत्सूत्रता, निपातः-तनं. 2 अक्रमः, उत्क्रमः, व्यतिक्रमः, अपर्यायः, अपरिपाटि-टी *f.*, अव्यवस्था. 3 व्यभिचारः, विपथगमनं, अमर्यादता, अनाचारः, दुर्वृत्तता. 4 वैषम्यं. **-ly,** *adv.* विधि-नियम-विरुद्धं, अविध्यनुरूपं, अयथाविधि, क्रमविरुद्धं; अनियमेन, अनियतवेलं, अविधितः; अक्रमेण.

Irrelative, *a.* असंबंधिन्, असंग, निःसंग.

Irrelevant, *a.* अप्रस्तुत, अप्रकृत, असंबद्ध, अप्रासंगिक (की *f.*), अनन्वित, प्रस्तुतबाह्य, असंगत. **-ly,** *adv.* अप्रकृतं, अप्रस्तुतं, असंबद्धं. **-Irrelevancy,** *s.* अप्रकृतता, अनन्वयः, असंबंधः, असंगति *f.*, अप्रस्तावः.

Irreligion, *s.* अधर्मः, अपूजा, अभक्ति *f.*, धर्मलोपः, देवनिंदा, पापता. **-Irreligious,** *a.* अधार्मिक (की *f.*), अधर्मनिष्ठ, विधर्म, धर्मभक्ति-हीन; अपुण्य, दुष्ट, पापिन्. **-ly,** *adv.* अधर्मेण, दुष्टवत्.

Irremediable, *a.* अप्रतिविधेय, अप्रतिकार्य, निरुपाय, अशक्यप्रतिकार, उपायातीत, अचिकित्स्य, दुःसाध्य.

Irremovable, *a.* अपरिहार्य, अनपानेय, स्थिर, अचल.

Irreparable, *a.* असमाधेय, असाध्य; अप्रतिकार्य, अशक्यप्रतिकार. **-y,** *adv.* अप्रतिविधेयं; 'the act i. damaged his reputation' तेन कर्मणा तस्य यशस्तथा क्षीणं यथा तत्प्रतिसंधातुमशक्यं.

Irreprehensible, *a.* अनिंद्य, अदूषणीय, निर्दोष.

Irrepressible, *a.* अनिवार्य, दुर्निवार, दुर्निग्रह.

Irreproachable, *a.* अनिंद्य, अगर्ह्य, अनवगीत; *See* **Faultless.**

Irresistible, *a.* अनिवार्य, दुर्निवार, अप्रतिकार्य, अनवग्रह, दुर्निग्रह, दुर्धर, अप्रतिहत. **-y,** *adv.* दुर्निवारं, अनवग्रहं.

Irresolute, *a.* अस्थिर-चल-लोल-मति-चित्त-बुद्धि, चलवृत्ति, चंचलधी, विकल्पशील, संशयात्मन्, अधीर, तरलमनस्. **-ly,** *adv.* अस्थिरचेतसा, चंचलवृत्त्या, लोलबुद्ध्या, अधीरं. **-ness, -Irresolution,** *s.* अस्थैर्यं, विकल्पशीलता, लोलमतित्वं, चलचित्तता, चंचलबुद्धि *f.*, लोलमति *f.*, अनवस्थिति *f.*, चापल्यं.

Irrespective, (of) *a.* अनपेक्ष्य, अगणयित्वा, अव्यपेक्ष्य, विहाय (with acc.), अनपेक्ष, निरपेक्ष, निर्व्यपेक्ष in comp.; *See* **Independent,** (of). **-ly,** *adv.* अनपेक्षं निरपेक्षं.

Irresponsible, *a.* अनुयोगाधीन, अप्रष्टव्य, अपृच्छ्याधीन.

Irrestrainable, *a.* *See* **Irresistible.**

Irretrievable, *a.* *See* **Irreparable, Irrecoverable.**

Irreverent, *a.* अनादरिन्, परिभाविन्, उपेक्षक, अवज्ञाकारिन्. **-ly,** *adv.* सावज्ञं, सावमानं, अनादरेण. **-Irreverence,** *s.* अवमानः, अवज्ञा, अनादरः, तिरस्कारः, परिभवः.

Irreversible, *a.* अपरिवर्तनीय, अलोप्य, अखंड्य.

Irrevocable, *a.* अनन्यथाकरणीय.

Irrigate, *v. t.* अव-सिच् 6 P, जलेन आप्लु c. or अभ्युक्ष् 1 P, अभिवृष् 1 P. **-ion,** *s.* सेकः, जलप्लावनं, अभ्युक्षणं.

Irriguous, *s.* जलाढ्य, सजल, जलपूर्ण, अनूप, बहूदक, जलसिक्त.

Irritate, *v. t.* कुप् c., क्रुध् c., रुष् c.; *See* **Enrage. -ion,** *s.* प्रकोपः, क्रोधः, रोषः, कोप or रोष-कारणं or हेतुः. **2** उत्तापः, उत्तेजनं, संतापः, दाहः; 'i. of the throat' कासः, क्षवथुः. **-ing, -ive,** *a.* संतापक; कोपावह. **-Irritable,** *a.* क्रोधन, कोपन, कोपशील, सुलभकोप, शीघ्रकोपिन्, चंडप्रकृति-स्वभाव. **-Irritability,** *s.* चंडस्वभावः-प्रकृति *f.*, शीघ्रकोपित्वं.

Irruption, *s.* *See* **Inroad.**

Ischury, *s.* मूत्रावष्टंभः, मूत्रकृच्छ्रं.

Island, Isle, *s.* द्वीपः-पं, अंतरीपः. **-a.** द्वैप्य, द्वीपस्थ, द्वैप (पी *f.*). **-Islander,** *s.* द्वीपवासिन् *m.*, द्वीपस्थः.

Isochronal, *a.* समकालीन.

Isolate, *v. t.* वि-युज् 7 A, 10, विच्छिद् 7 P, विश्लिष् c.; *See* **Separate. -ed,** *a.* वियुक्त, अन्यासंश्लिष्ट, अनन्यसंसक्त, गतसंग. **-ion,** *s.* विच्छेदः, विश्लेषः, असंगः, पृथक्त्वं.

Isosceles, *a.* समद्विभुज.

Issue, *v. i.* निर्गम् 1 P, अप-इ 2 P, निर्-या 2 P, निःसृ 1 P, निष्क्रम् 1 U, 4 P. **2** स्रु 1 P, निः-प्र-°; क्षर् 1 P, गल् 1 P, स्यंद् 1 A. **3** उत्-प्र-भू 1 P, प्र-जन् 4 A, उत्पद् 4 A, प्रवृत् 1 A; *See* **Arise. 4** निष्पद्, निर्वृत्, समाप् pass. **-v. t.** निःसृ c., प्रचर्-लृ c., निर्गम् c. (गमयति), बहिर्गम् c. **2** प्रकाश् c., प्र-ख्या c. (ख्यापयति), घुष् 10. **-s.** निर्गमः, निःसरणं, निर्याणं, निष्क्रमणं. **2** फलं, परिणामः, उदर्कः, अंतः, उत्तरफलं, उत्पन्नं; *See* **End. 3** संतति *f.*, प्रजा, अपत्यं, संतानः-नं. **4** रक्तातिसारः, स्रावः; 'matter at i.' विवादवस्तु *n.*, विचार्यविषयः. **-less,** *a.* निरपत्य, निर्वंश, निःसंतान, अप्रजस्, निरन्वय.

Isthmus, *s.* संयोगभूमि *f.*

It, *pron.* Ex. by *m. f.* or *n.* form of pronouns, corresponding to the noun; sometimes not ex. at all; 'what is i. that you want' किमपेक्ष्यते त्वया; 'i. is good to study' अध्ययनं प्रशस्यं.

Itch, *s.* कंडु-डू *f.*, खर्जूः, कंडूया; (dry) कच्छु-च्छू *f.*, पामा, पामन् *f.*, विचर्चिका. **2** कंडूयनं. **3** अत्यभिलाषः, अतिस्पृहा, इच्छातिरेकः. **-v. i.** कंडूयति-ते (D.). **2** अत्यंतं इष् 6 P or अभिलष् 1, 4 P, गृध् 4 P. **-y,** *a.* कंडूल, पामन, कच्छुर.

Item, *s.* विषयः, अर्थः, पदं, अधिकरणं, भिन्नभागः.

Iterate, *v. t.* पुनः पुनः वद् 1 P or वच् 2 P. **2** पुनः पुनः कृ 8 U. **-ion,** *s.* पुनरुक्ति *f.*, पौनरुक्त्यं, पुनर्वचनं, पुनःकरणं. **-ive,** *a.* पुनर्वादिन्, पुनःकारिन्.

Itinerant, *a.* भ्रमणशील, अटमान, परिभ्रमिन्, भ्रमणकारिन्, अवनिचर.

Itinerary, *s.* प्रवासवृत्तांतलेखः.

Itinerate, *v. i.* *See* **Travel.**

Ivory, *s.* गज-हस्ति-दंतः, दंतः (the sense being clear). **-a.** (*s.*) in comp.; 'i. doll' दंतपांचालिका.

Ivy, *s.* तरुरोहिणी, वृक्षलता.

J

Jab, *v. t.* अप-, व्यध् 4 P.

Jabber, *v. i.* प्रजल्प् 1 P, प्रलप् 1 P, अव्यक्तं-अस्पष्टं-वद् 1 P, त्वरितं वच् 2 P, **-er,** *s.* वाचालः-टः, वावदूकः, जल्प(ल्पा)-कः. **-ing,** *s.* जल्पः, प्रलापः, प्रजल्पः, अस्पष्टं वचनं.

Jack, *s.* पनसः. 2 वृक्षः, उपस्तंभः, आधारः; 'j.-fruit' पनसं.

Jackal, *s.* सृ(शृ)गालः, गोमायुः, जंबू(बु)कः, क्रोष्टु *m.*, फेरवः, भूरिमायः, शिवा, मृगधूर्तकः, वंचु(च)कः, फेरुः.

Jackanapes, *s.* वानरवृत्ति *f.*, मर्कटशीलं.

Jackass, *s.* गर्दभः, रासभः, खरः.

Jackdaw, *s.* काकः, द्रोणकाकः, द्रोणः.

Jacket, *s.* कूर्पासकः, कंचुकः, निचोलः.

Jack-ketch, *s.* घातकपुरुषः, उद्बंधकः.

Jack-pudding, *s.* भंडः, विदूषकः, वैहासिकः.

Jaculate, *v. t.* निर्-,अस् 4 P.

Jade, *s.* कदश्वः, अश्वकः. 2 पुंश्चली, बंधकी, कुलटा, भ्रष्टा, असती, असाध्वी. **-v. t.** खिद् c., क्रम् c., श्रम् c., आयस् c., अवसद् c **-v. i.** श्रम् 4 P, क्लम् 1, 4 P, आयस् 1, 4 P, अवसद् 1 P, खिद् pass. ग्लै 1 P. **-ed,** *a.* क्लांत, श्रांत, खिन्न, श्रमार्त, ग्लान. **-Jadish,** *a.* दुष्ट, पापीयस्, कुत्सित, कु-कद्-दुर्-pr.

Jag, *s.* भंगः, दंतः, छेदः. **-v. t.** भंगुरी-दंतुरी-कृ 8 U, ककचरूपेण छिद् 7 P. **-ged,-gy,** *a.* दं:ुर, अनुक्रकच, भंगुर, क्रकचाकार.

Jaggery, *s.* गुडः, मत्स्यंडी, फणितं.

Jail, *s.* कारा, कारागृहं, कारागारं, कारावेश्मन् *n.*, बंधनागारं, बंधनालयः, बंधन-निरोध-स्थानं, बंदिशाला, गुप्ति *f.* **-er,** *s.* काराध्यक्षः, बंदिपालः, काराधिपतिः, कारागृहावेक्षकः.

Jam, *s.* मिष्टान्नं, स्वाद्वन्नं, संधितं. **-v. t.** सं-पीड् 10, संबाध् 1 A, संमृद् 9 P, क्लिश् 9 P. **-med,** *a.* संपीडित, संबाध, संकुल, संकट.

Jangle, *v. i.* वि-वद् 1 A, विप्र-लप् 1 P, वि-प्रति-पद् 4 A, कलहं कृ 8 U. **-v. t.** Rattle, q. v. **-s., -ing,** *s.* विवादः, विप्रलापः, वा-क्कलहः, वाग्युद्धं.

Janitor, *s.* द्वाःस्थः, द्वारपालः, प्रति(ती)हारः.

Janty, *a.* चपल, लघु-चल-स्वभाव, सरस.

January, *s.* पौषमाघं.

Jape, *v. t.* परि-उप-अव-हस् 1 P.

Jar, *s.* घटः-टी, कुंभः, कलशः-शी-शं; (earthen) मृद्भांडं, मृण्मयं पात्रं; कुटः, निपः; 'a large j.' मणिकः, अलि(लं)जरः. 2 कर्कशध्वनिः-शब्दः, संघर्षणध्वनिः, कटु-परुष-स्वनः. 3 कलहः, विसंवादः. 4 संघट्टः, समाघातः, परस्पराघातः. **-v. i.** संघट्ट् 1 A, समाहन् 2 P. 2 कर्कशं ध्वन्-स्वन् 1 P. 3 विद् 1 A, कलहायते (D.) विप्र-लप् 1 P. **-ring,** *a.* कर्णकर्कश, परुष, कटु, कर्कश-शब्दकारिन्. 2 परस्परविरुद्ध; *See* **Inconsistent.**

Jargon, *s.* प्रलपितं, अनर्थकं वचनं, अनर्थक-वाग्प्रपञ्चः; संकीर्णवाच् *f.*

Jasmine, *s.* भूपदी, श(शी)तभीरुः, मल्लिका, आस्फोटा (wild); मागधी, गणिका, यूथि-का, अंबष्ठा; अतिमुक्तः, पुंड्रकः; वासंती, माधवी, सुमनाः, मालती, जाति-ती *f.*, सप्तला, नवमल्लिका-मालिका; माध्यं, कुंदः-दं (different species).

Jasper, *s.* सूर्यकांतः.

Jaundice, *s.* कामला-लः, पांडुः, पांडुरोगः. **-ed,** *a.* कामलोपहत, पांडुग्रस्त. 2 साचीकृत, सत्यात् परिवर्तित.

Jaunt, *v. i.* विहारार्थं परिभ्रम् 1, 4 P or पर्यट् 1 P. **-s.** विहारः, पर्यटनं.

Javelin, *s.* शूलः-लं, शल्यं, शंकुः, प्रासः, शक्ति *f.*, अस्त्रं, कुंतः.

Jaw, *s.* हनु *m. f.* 2 वक्त्रं, मुखं; 'lower j.' पीचं, कुंजः, चिबुकं, चिबुः, 'locked j.' हनुग्रहः; 'j.-tooth' दंष्ट्रा; 'fallen in the j. s of death' मृत्योर्मुखे पतितः, मृत्युदंष्ट्रां-तर्गतः. 3 भर्त्सना, वाक्पारुष्यं, तर्जनं, आक्रो-शः. **-v. i.** तर्ज् 1 P, 10 A, भर्त्स् 10 A, आक्रुश् 1 P. **-ed,** *a.* हनुमत्, हनुविशिष्ट.

Jay, *s.* चाषः-सः, किकीदिविः, किकिदिवः-विः, किकीदिवी:-वः, किकिः, दिवः.

Jealous, *s.* मत्सरिन्, समत्सर, सासूय, साभ्य-सूय, सेर्ष्य, परोत्कर्षासहन, परसुखद्वेषिन्; *See* **Envious.** 2 प्रेमसंशयिन्, शंकाशील, प्रीत्याशंकिन्; 'a j. husband' परपुरुष-व्य-भिचार-जार-शंकित; 'a j. wife' परस्त्रीशं-किनी. 3 कृतादर, आवृत, साभिमान, सावधा-न, अनुपेक्षक. **-ly,** *adv.* समत्सरं, सेर्ष्यं, सासूयं, साभ्यसूयं; साभिमानं. **-ness, -y,** *s.* मत्सरः, मात्सर्यं, असूया, ईर्ष्या, अभ्यसूया, सापत्न्यं, परोत्कर्षद्वेषः. 2 शंकाशीलता, व्य-भिचारशंका, प्रेम-प्रीति-शंका. 3 सावधानता, अभिमानावेक्षा.

Jeer, *v. i.* उप-अव-हस् 1 P, अव-आ-क्षिप् 6 P, अव-ज्ञा 9 U, तिरस्कृ 8 U, गर्ह् 1, 10 A, अवहासास्पदीकृ. **-s.** उप-अव-हासः, अवक्षेपः; अवज्ञा. **-ingly,** *adv.* सोपहासं, सावक्षेपं; सावज्ञं.

Jejune, *a.* शुष्क, रूक्ष, नीरस, विरस, निःसार, निःसत्त्व.

Jelly, *s* श्यान-सांद्र-द्रव्यं.

Jeopardy, *s.* संशयः, संदेहः, शंका; 'j. of life' जीवितसंशयः, प्राणसंदेहः. **-Jeopard,** *v. t.* **-ize,** *v. t.* संशये पत् c., संशयस्थ-संशयित-*a.* कृ 8 U; 'one who j.-es his life' संशयितजीवितः; *See* **Danger** also.

Jerk, *v. t.* (सहसा) चल् c., वि-धू 6 P, 5, 9 U; लघु-सहसा तड् 10 or प्रहृ 1 P, अकस्मात्-सवेगं-क्षिप् 6 P. **-s.** चालनं, लघुप्रहारः, लघ्वाघातः, लघु-आकास्मिक-क्षेपः.

Jerkin, *s. See* **Jacket.**

Jessamine, *s. See* **Jasmine.**

Jest, *s.* परि(री)हासः, नर्मन् *n.*, हास्यं, विनोदोक्ति *f.*, प्रहसनं, विनोदभाषणं, परिहासोक्तिः, नर्मालापः; 'truce to (fie upon) your j. s' धिक्प्रहसनं (U. 4.), अलं परिहासेन; 'uttered in j.' परिहासजल्पितं; 'made a j. of the matter' तमर्थं परिहासमिव मेने. **2** खेला, क्रीडा, केलि *f.*, कौतुकं; 'in j.' परिहासेन, परिहासपूर्वं. **-v. i.** परिहस् 1 P, विनोद-परिहास-वाक्यं वद् 1 P or उदीर् c.; क्रीड् 1 P. **-er,** *s.* वैहासिकः, परिहासयितृ *m.*, परिहास-विनोद-कारिन् *m.*, भंडः, चाटुपटुः; 'king's j.' विदूषकः, नर्मसचिवः. **-ingly,** *adv.* परिहासपूर्वं, सपरिहासं, सविनोदं.

Jet, *s.* जलोत्क्षेपः. **2** कृष्णप्रस्तरः; 'j.-black' घनकृष्ण, अतिकृष्ण. **-ty,** *a.* कृष्णवर्ण.

Jewel, *s.* मणि *m f.*, रत्नं; 'j. of a woman' स्त्रीरत्नं; 'j.-house' मणिशाला, रत्नागारं; 'j.-mine' रत्नाकरः, रत्न-मणि-खनि *f.*-भूमि *f.* **-led,** *a.* रत्नवत्, मणि-रत्न-मय (यी *f.*), रत्नसनाथ, मणि-रत्न-खचित, रत्नानुविद्ध. **-ler,** *s.* रत्नाजीविन् *m.*, मणिकारः, रत्नकारः. **-Jewelry,** *s.* रत्नानि (pl.), रत्नादिकोशः-षः.

Jiffy, *s.* निमेषः, क्षणः.

Jig, *s.* नृत्यविशेषः. **2** वंचना, व्याजः, छलं.

Jilt, *s.* प्रतारिका, चपला, वंचिका, संकेतलंघिनी. **-v. i.** प्रेमसंकेतं लंघ् 1 A, 10, प्रेमाविषये वंच् 10, or प्रतृ c., खंड् 10.

Jingle, *v. i.* शिंज् 2 A, 10, क्वण् 1 P, वि-रु 2 P, झणझणायते (D.), कलं स्वन् 1 P. **-s., -ing,** *s.* शिंजितं, शिंजा, झणत्कारः, झणझणस्वनः, क्वणितं, क्वणनं, कलरवः.

Job, *s.* कार्यं, कृत्यं, व्यापारः, क्रिया. **2** लघुक्षुद्र-नीच-क्रिया. **3** स्वार्थपरं कार्यं, आत्मवृद्ध्यर्थं कर्मन् *n.* **-v. i.** क्षुद्रकर्माणि कृ 8 U, स्वार्थमुद्दिश्य कार्यं कृ. **2** पण् 1 A. **3** *v. t.* अवव्यध् 4 P. **-ber,** *s.* क्षुद्रकर्मकारिन् *m.*, परार्थं क्रयविक्रयकारिन् *m.*, स्वार्थप्रवर्तकः, क्रयविक्रयिन् *m.* **-bing,** *s.* क्षुद्रकर्मव्यवसायः, स्वार्थप्रवृत्ति *f.*

Jockey, *s.* अश्वज्ञः, हयज्ञः, अश्वविद् *m.*, अश्वकोविदः, अश्वविद्याविशारदः. **-v. t.** अश्वज्ञ इव प्रतृ c. or वंच् 10. **-ism.** *s.* अश्वविद्या-शिक्षा.

Jocose, Jocular, *a.* हास्यकर (री *f.*), विनोदिन्, हास्यावह, विनोदात्मक, सरस, हास्यगर्भ, सकौतुक; (of persons) परिहासशील, परिहासक, विनोद-नर्मालाप-पर, कौतुकिन्. **-ly,** *adv.* परिहासेन, परिहासपूर्वं, सकौतुकं, विनोदार्थं, रसिकवत्. **-ness, -ity,** *s.* परिहासशीलता, रसिकता, विनोदः, कौतुकं, उल्लासः, हर्षः, प्रमोदः.

Jocund, *a.* प्र-,हृष्ट, प्र-,मुदित, आनंदवृत्ति. **-ity,** *s.* उल्लासः, प्रहर्षः, आनंदः; *See* **Glad.**

Jog, (on) *v. i.* मंदं मंदं प्रसृप् 1 P or चल् 1 P or सृ 1 P. **-v. t.** अरत्निना तड् 10, ईषत् चल् c. **-s.** ईषदाघातः, ईषत्प्रहारः-चालनं; 'j.-trot' गज-मंद-गति *f.*, मंदप्रयाणं.

Join, *v. t.* युज् 7 U, 10, सं-आ°-,संसंज् 1 P, यु 2 P, संश्लिष् c., सं-धा 3 U, संबंध् 9 P, संहन् 2 P, एकत्र कृ 8 U, संग्रंथ् 9 P, योक्त्रयति (D.), घट् c. (घटयति), संपृच् 2 A, 7 P. **2** (Go to) समुपागम् 1 P, संकृ 2 P, संमिल् 6 P, संगम् 1 A; pass. of roots above (with instr.); 'j. hands' अंजलिं बंध् 9 P, प्रां(सां)जलि-*a.* भू, हस्तौ समा-नी 1 P; 'j. ed their hands in marriage' विवाहविधिना ताभ्यां अन्योन्यपाणिग्रहणं कारयामास, वधूवरं संगममांचकार **-ed,** *a.* युक्त, युत, संयुक्त, संयुत, संश्लिष्ट, संहत, सं-समा-सक्त, लग्न, संलग्न, संबद्ध, संपृक्त, संहित, सहित, संगत, समेत, मिलित, घटित. **-er,** *s.* तक्षकः, रथकारः, सूत्रधारः, तष्टृ *m.*, तक्षन् *m.*, काष्ठतक्ष् *m.*, वर्धकिः. **-ery,** *s.* काष्ठतक्षणं. **-ing,** *s.* सं-,योगः, संधिः, संसर्गः, संधानं, संश्लेषः, संघातः, संगमः, संसक्ति *f.* **-Joint,** *s.* संधिः, पर्वन् *n.*, ग्रंथिः, कांडः-डं, अस्थिग्रंथिः-संधिः; 'out of j.' विलग्न, विसंधि. **-a.** संयुक्त, समवेत, एककार्यव्यापृत, संहत. **2** असंविभक्त, अविभक्त, साधारण (णी *f.*), सामान्य, सह in comp.; संघातवत्, संभूयकारिन्; 'j. proprietor' सहाधिकारिन् *m.*; 'j. family property' संसृष्टधनं; 'members of a j. family' संसृष्टाः, संसृष्टिनः; 'with j. labour' संभूयश्रमेण सर्वेषां यत्नेन; 'j.-stock company' संभूयसमुत्थानं; 'j.-heir' भागिन् *m.*, संविभागिन् *m.*, समांशहरः, समांशिन् *m.* **-v. t.** संधियुक्त-*a.* कृ; ex. by (*s.*). **-ed,** *a.* संधिविशिष्ट, ग्रंथिल, संधि-ग्रंथि-युक्त, पर्ववत्. **-ly,** *adv.* समं, सह, संभूय, संयोगेन, सहितं, समवायेन, एकीभूय, एकचित्तीभूय, युगपत्. **-Jointure,** *s.* विधवाधनं; स्त्रीधनं.

Joke, -er, *See* **Jest, -er**

Jole, *s.* गंडः, कपोलः.

Jolly, *a.* प्र-,हृष्ट, सानंद, उल्लसित, प्रमोदिन्, हृष्ट-प्रीत-हृदय; परिहासशील, विनोदिन्, विलासिन्, विनोदशील. **-ity,** *s.* उल्लासः, आनंदः, प्र-,हर्षः, प्रमोदः, उत्सवः. **-ness,** *s.* विनोदपरता, प्रहासः,

Jolt, *v. t.* संक्षुभ् 9 P or c. **-v. i.** क्षुभ् 1 A, 4 P. **-s., -ing,** *s.* संक्षोभः, उद्घातः, आकास्मिकक्षेपः.

Jolthead, *s.* स्थूलबुद्धिः, मूर्खः, मूढः; *See* **Fool.**

Jostle, *v. t.* स्कंधसाहनेन निराकृ 8 U or निः-सृ c. or निर्-धू 6 P, 5, 9 U or निर्-अस् 4 U; परस्परं समाहन् 2 P or संमृद् 1 P or संमर्द् 9 P, अभिसं-पत् 1 P; संघट्ट् 1 A. **-ing,** *s.* परस्परसमाघातः-घर्षणं, अन्योन्यसंमर्दः, अभिसंपातः.

Jot, *s.* कणः, लवः, अणुः, लेश-लव-कण-बिंदु-मात्रं, तिलमात्रं. **-v.** *t.* (स्मरणार्थं) लिख् 6 P or अंक् 10. **-ting,** *s.* अभिलिखितं.

Journal, *s.* वार्ता-वृत्त-समाचार-पत्रं or पत्रिका. **-ist,** *s.* वृत्तपत्रप्रकाशकः-लेखकः.

Journey, *s.* प्रयाणं, प्रस्थानं. प्रवासः. यात्रा, देशभ्रमणं-पर्यटनं, अध्वन् *m.*, मार्गः, अध्व or मार्ग-गमनं or क्रमणं, ' on account of the fatigues of j. ' अध्वसंजातखेदात्; उत्थाय पुनरध्वहत् (Ka. 299). ' resumed his j.' &c., ' it is only a week's j. ' सप्ताहगम्योऽध्वा; ' to return from a j. ' प्रवासाद् उपावि-वृत् 1 A; ' may the j. be pleasant to you ' शिवास्ते पंथानः संतु. **-v.** *i.* प्र-या 2 P, मार्गेण गम् or व्रज् or चर् 1 P or या, पर्यट् 1 P, परिभ्रम् 1, 4 P वह् 1 P, दिवा रात्रौ चावहत् (Ka. 301); ' to j. abroad' प्रवस् 1 P. **-er,** *s.* अध्वगः, पथिकः, पांथः, यात्रिकः. **-Journeyman,** *s.* वैतनिकः, हस्तकर्मकारः.

Jovial, *a.* उल्लासिन्, सदानंदिन्.

Joy, *s.* आनंदः, हर्षः, उत्सवः.

Jubilant, *a.* जयघोषं कुर्वाण, जयध्वनिकारिन्.

Jubilate, *v. i.* जयघोषं कृ 8 U, नंद् 1. A, हृष् 1 P.

Jubilee, *s.* प्रहर्षः, महोत्सवानंदः, महोत्सवः, उत्सवकालः.

Judge, *s.* प्राड्विवाकः, अ(आ)धिकरणिकः, अक्षदर्शकः, धर्माध्यक्षः, धर्माधिकारिन् *m.*, न्यायाध्यक्षः, निर्णेतृ *m.*, दंडनायकः. **2** (In general) अभिज्ञः, गुणदोषज्ञः, विशेषज्ञः, परीक्षकः, परिच्छेदकः, विवेकिन् *m.*, गुणग्राहिन् *m.*, रसज्ञः, तद्विद् *m.*,**-v.** वि-विच् 3, 7 U, परिच्छिद् 7 P, वि-ज्ञा 9 U, विभू c., विचर् c., निर्णी 1 P, निश्चि 5 U, अव-निर्-धृ 10, अव-परि-ईक्ष् 1 A, तीर् 10, अनुसं-धा 3 U. **2** वितर्क् 10. विमृश् 6 P, विगण् 10, विकल्प् c., मनसा विचर् or विविच्, मन् 4 A; ' it is for you to j. whether &c. ' एतद्विषये भवान् प्रमाणं; ' j. me by my acts ' फलेन मद्गुणदोषनिर्णयः क्रियतां; ' to j. ill or wrongly ' मिथ्या क्लृप् c. or संभू c. or मन्. **-ment,** *s.* विवेकः, परिच्छेदः, विचारः- रणा, विज्ञानं, विभावनं, निर्धारणा, निर्णयः, निश्चयः, संकल्पः, अवधारणं-णा. **2** (. Judicial decision) निर्णयः, विचारः, निर्णयपादः, आधर्षणं; तीरणं, दंडाज्ञा. **3** अनुभवः, तर्कः, ज्ञानं, अनुमानं. **4** मति *f.*, बुद्धि *f.*, मतं, अभिप्रायः, संकल्पः, बोधः; ' according to one's j. ' यथामति, यथाबुद्धि. **5** (Divine j.) ईश्वराज्ञा, ईश्वर-विधि-नियमः--शासनं; ' j.-day ' विचारदिनं; ' j.-hall ' न्यायसभा, विचार-धर्म-सभा; ' j.-seat ' व्यवहारासनं, न्यायासनं, धर्मासनं. **-Judicatory,** *s.* धर्म-विचार-न्याय-सभा, व्यवहारमंडपः, धर्माधिकरणं. **2** न्यायप्रणयनं. **-Judicature,** *s.* न्यायाधिकारः, व्यवहारदर्शनाधिकारः; *See* **Judicatory** above. **-Judiciary,** *a.* विचारक, व्य(व्या)वहारिक (की *f.*). **-Judicial,** *a.* व्यवहारविषयक, व्यवहार in comp.; ' j. proceeding ' व्यवहारदर्शनं, व्यवहारः, न्यायविचारः. **-ly,** *adv.* व्यवहारानुसारेण, यथाव्यवहारं, न्यायानुरूपं. **-Judicious,** *a.* (Act) समीक्ष्य-विमृश्य-कृत, न्याय्य, धर्म्य, समंजस, उचित, यथान्याय, सविवेक, युक्त योग्य. **2** (Persons) विमृश्य-समीक्ष्य-कारिन्, विवेकिन्, नीतिमत्, परिच्छेदक, नयज्ञ, प्राज्ञ, विवेकदृश्वन्, विशेषज्ञ, सदसद्दर्शिन्. **-ly,** *adv.* युक्तं, समंजसं, यथान्यायं, उचितं, सम्यक्. **2** सविवेकं, सपरिच्छेदं, सुविमृश्य, सुविचार्य, प्राज्ञ-विज्ञ-वत्.

Jug, *s.* कुंभः, कलशः, कंसः, उदकपात्रं; *See* **Jar.**

Jugate, *a.* संयुक्त, संश्लिष्ट.

Juggle, *v.* मुह् c., छल् 10, वंच् 10, दृष्टिं मुह् c. or बंध् 9 P, मायां-कुहकं-इंद्रजालं-कृ 8 U. **-s., -ing, -ry,** *s.* माया, कुसृति *f.*, दृष्टिमोहः-बंधः, इंद्रजालं, कुहका-कं, इंद्रियदृष्टि-मोहः, हस्तलाघवं-चापल्यं. **2** वंचना, छलं, कूटता, प्रतारणा. **-er,** *s.* ऐंद्रजालिकः, मायिन् *m.*, मायाकारः, मायाजीविन् *m.*, कुहकजीविन् *m.*, कौसृतिकः, अ(आ)हितुंडिकः.

Jugular, *a.* कंठस्थ, कंठ्य.

Juice, *s.* रसः, द्रवः, सारः, निर्यासः, आसवः, 'j. issuing from the elephant's temples' मदः, दानं, मदवारि. **-less,** *a.* नीरस, अरस, विरस, असार, सारहीन शून्य, शुष्क, निःक्षीर. **-y,** *a.* रसमय (यी *f.*), रसपूर्ण, सरस, बहुरस, रसाढ्य, सार-रस-वत्.

Jujube, *s.* बदरी, कर्कंधु-धू *m. f.*, कोलि *f.*, कोलाली; (fruit) बदरं, कोलं, कुवलं, फेनिलं, सौवीरं, घोंटा.

July, *s.* आषाढश्रावणं.

Jumble, *v. t.* संकॄ 6 P, संमिश्र् 10, संक्षिप् 6 P, संकुल-संकरी-कृ 8 U **-v. i.** संकृ pass., संकरी-संकुली-भू 1 P. **-s.** संकरः, सं-,मिश्रणं, संक्षोभः, संकुलता, संनिपातः.

Jump, *v. i.* प्लु 1 A, वल्ग् 1 U, स्कंद् 1 P. ' j. about ' नृत् 4 P; ' j. over ' लंघ् 1 A, 10; ' j. up ' उत्प्लु, उत्पत् 1 P; ' j. with ' **Agree,** q. v. **-s.,-ing,** *s.* प्लवनं, उत्पतन

वल्गितं, प्लुतं-ति *f*., प्लवः, आस्कंदः. झंपः-पा. **-er,** *s*. प्लवकः, झंपिन् *m*.

Junction, *s*. स-,योगः, संगमः, संमिलनं, संगति *f*., समागमः. संश्लेषः, संधिः, संसर्गः, संघातः, संसक्ति *f*., संपर्कः; 'j. of rivers' संभेदः, संगमः. 2 संधिस्थानं.

Juncture, *s*. वेला, समयः; कष्टकालः-समयः, संकटवेला. 2 संधिः, ग्रंथिः.

June, *s* ज्येष्ठाषाढकं.

Jungle, *s*. गुल्मावृतं स्थानं.

Junior, *a*. कनीयस्, अवर, अवरज, यवीयस्, अवरपदभाज्.

Junket, *s*. निभृतोत्सवः. 2 मिष्टान्नं, मोदकः.

Junta, Junto, *s*. सभा, समाजः, गूढसंसर्गः, कुसंसर्गः.

Juridical, *a*. व्य(व्या)वहारिक (की *f*.); *See* **Judicial.**

Jurisconsult. *s*. स्मृतिशास्त्रज्ञः, धर्मशास्त्रकोविदः.

Jurisdiction, *s*. अधिकारः, व्यवहारदर्शनाधिकारः, न्यायप्रभुत्वं.

Jurisprudence, *s*. धर्मशास्त्रं, स्मृतिशास्त्रं, व्यवहार or विद्या-ज्ञानं or शास्त्रं, विधिः; 'a head of j.' व्यवहारविषयः,-पदं.

Jurist, *s*. धर्मशास्त्रकोविदः, स्मृतिज्ञः.

Jury, *s*. सभ्याः; प्रमाणपुरुषगणः.

Just, *a*. (Of persons) न्यायवर्तिन्, न्यायिन्, न्यायशील-पर, साधुवृत्ति, ऋजु, विमलात्मन्, निष्कपट, निर्व्याज, शुचि, न्यायपरायण, धार्मिक-सात्त्विक (की *f*.). 2 न्याय्य, धर्म्य, यथान्याय, न्यायानुसारिन्, सत्य, तथ्य, योग्य, युक्त, यथार्थ, उचित, सम्यच्. 3 सम, समवृत्ति, निःपक्षपात, समदर्शिन्. 4 संपूर्ण, अविकल, अन्यून. **-***adv* अंतिकं-के, समीपं, निकटे. 2 प्रायः, प्रायशः; oft. by भूयिष्ठ, कल्प, प्राय in comp., or by desid.; *See* **About.** 3 सद्यः, अचिरादेव, नातिचिरात्, प्राक्; oft. by एव, मात्र in comp.; 'j. now' अधुनैव; 'it is j. proper' उचितमेव; 'j. dead' सद्योमृत; 'j. born' जातमात्र. 4 युक्तं, सम्यक्, यथार्थं, यथावत्. 5 तावत् 'j. come here' इतस्तावदागम्यतां; 'j. so' एवमेव, तथैव, एवमेतत्, अथ किं, युक्तं, युज्यते; 'j. as' 'j. like' इव, यद्वत्, or निर्विशेष in comp.; 'stay j. as in your own house' स्वगृहनिर्विशेषमत्र वस; 'bred j. like one's own children' स्वपुत्रनिर्विशेषं संवर्धित. कष्टेन, कृच्छ्रेण. **-ly,** *adv*. निर्व्याजं, निर्व्यलीकं, मार्दवेन. 2 यथान्यायं, न्यायेन, धर्मेण, न्यायतः, धर्मतः, यथाधर्मं, न्यायानुसारेण, सम्यक्, यथावत्. 3 सत्यं, अवितथं, यथार्थं, अर्थतः, यथावत्, यथातथं, यथार्हं, उपपन्नं, यथोचितं, युक्तं, स्थाने, यथायोग्यं, अंजसा. **-ness,** *s*. न्याय्यता, यथार्थता, योग्यता, औचित्यं, युक्तता; साम्यं, पक्षपातः. **-Justice,** *s*. धर्मः, न्यायः, नयः, नीति *f*., न्यायिता, ऋजुता, साधुता. 2 न्याय्यता, युक्तता, योग्यता, यथार्थता, सत्यता, युक्ति *f*., याथार्थ्यं. 3 साम्यं, समदर्शित्वं, अपक्षपातः, सर्वसमता. 4 न्यायदंडः, योग्य-दंडः-शिक्षा, अपराधानुरूपो दंडः. 5 धर्माध्यक्षः; प्राड्विवाकः; *See* **Judge;** 'court of j.' न्याय-धर्म-सभा, व्यवहारमंडपः. **-ship,** *s*. धर्माधिकारः, न्यायाध्यक्षत्वं. **-Justiciary,** *s*. **Judge,** q. v. **-Justify,** *v. t*. न्याय्य -*a*. इति प्रति-पद् c. or प्रदृश् c.; शुध् c, दोषं निराकृ 8 U or निवार् 10 or शुध् c. or मृज् 2 P, दोषात् मुच् 6 P or c. **-able,** *a* निवार्यदोष, शोधनीय, शुद्धिक्षम. **-ication,** *s*. शुद्धि *f*., शोधनं, दोषशुद्धिः, दोषमुक्ति *f*. -मार्जना, दोषप्रतीकारः, विमोचनहेतुः, अपव्यप-देशः. **-er,** *s*. शोधकः, दोषनिवारकः.

Justle, *v*. *See* **Jostle.**

Jut, *v. i*. प्रलंब् 1 A, बहिर्वृत् 1 A or स्था 1 P. **-***s*. प्रलंबनं, आभोगः, प्रालंबः.

Jute, *s*. शणं.

Juvanescent, *a*. तरुणीभवत्.

Juvenile, *a*. तरुण, अल्पवयस्क, युवन्, कौमार (री *f*.), अभिनववयस्. **-ity,** *s*. यौवनं, तारुण्यं, कौमारं, यौवनावस्था, तारुण्यभावः.

Juxtapose, *v. t*. संनि-धा *c*. **-ition,** *s*. सान्निध्यं, संनिधिः, संस्थिति *f*., सन्निकर्षः, संसर्गः, नैकट्यं, उपश्लेषः.

K.

Kaw, *v. i*. कै 1 P, ध्वां(ध्रां)क्ष् 1 P. **-***s*. काकरवः-रुतं

Keel, *s*. नौतलं.

Keen, *a*. तीक्ष्ण, शित, निशित, शात, निशात, शितधार, तीक्ष्णाग्र; तीव्र, तिग्म, प्रखर. 2 व्यग्र, उच्चंड, उन्मुक, उत्कट, कुतूहलिन्; *See* **Eager.** 3 सूक्ष्म, कुशाग्र-धीय, विदग्ध. 4 उग्र, कटु, अरुंतुद, मर्मस्पृश्, तिग्म (words); 'k. words' वागिषुः, वागग्निः; 'k.-eyed' 'k.-sighted' सूक्ष्ममति, तीक्ष्ण-सूक्ष्म-बुद्धि, कुशाग्रमति-बुद्धि, दूरदर्शिन्. **-ly,** *adv*. तीक्ष्णं, तीव्रं, उग्रं, प्रखरतया. **-ness,** *s*. तीक्ष्णता, तीव्रता. 2 व्यग्रता, उच्चंडता, कौतूहलं, अत्युत्साहः. 3 सूक्ष्मता, विदग्धता, कुशाग्रमतित्वं, बुद्धिसूक्ष्मता. 4 कटुता, तिग्मता, उग्रता.

Keep, *v. t*. रक्ष् 1 P, पा 2 P, पा c. (पालयति), गुप् 1 P, त्रै 1 A, अव 1 P. 2 धृ 1 P, 10; धा 3 U, नि-आ-°, निविश् c., स्था c. (स्थापयति), न्यस् 4 U. 3 रुध् 7 U,

नि-अव-उप-°, धृ, बंध् 9 P, निवार् 10, प्रति-नि-षिध् 1 P, नि-सं-यम् 1 P. 4 (As cattle) निरुप् 10, पा c., रक्ष्. 5 (As a secret) न प्रकाश् c. or भंज् 7 P, or भिद् 7 P गुप्, रक्ष्. 6 (Observe) आचर् 1 P, अनु-ष्ठा 1 P, वि-धा, कृ, सेव् 1 A, भज् 1 U, आश्रि 1 U, आ-स्था 1 U, आ-अव-लंब् 1 A. 7 शुभ् c., नि-र्वह् c., अप-वृज् 10, पूर् 10, तृ 1 P, साध् 5 P or c., पा c. (पालयति) (as a promise). 8 भृ 1 P, 3 U, पुष् c., पा c.; (as servants) व्यापृ c., सेवार्थं नियुज् 7 A, 10, वेतनं-भृतिं-दा 3 U, 'to k. bad hours' वेलातिक्रमेण स्वप् 2 P; 'to k. in mind' हृदये-मनसि-कृ, अव-धृ; 'k. company with' संगम् 1 A, सं-इ 2 P, सह वस् or चर् 1 P, संवस्; *See* **Associate.** -*v. i.* स्था, वृत् 1 A, आस् 2 A, न विरम् 1 P or निवृत् or विश्रम् 4 P, with pres. part. (when followed by p. p. &c.); 'he kept weeping' रुदन्नास्त, रुदन्नोपरराम; 'k. going up and down' आरोहावरोहं कुर्वन्नास्त. 2 संसंज्-संश्लिष्-अनुबंध- pass., लग् 1 P. 3 वस् 1 P. -*s.* रक्षा-क्षणं, पालनं, गुप्ति *f.* 2 अवस्था, दशा, स्थिति *f.*, वृत्ति *f.*, भावः. 3 भृति *f.*, पोषणं. 4 दुर्गं, कोटः. 5 कारावंधनं, निरोधः, गुप्तिः. **-back, -from,** निग्रह् 9 P, संयम्, संह्र 1 P, निवृ c.; (*v. i.*) निवृत्, विरम्. **-in,** गुह् 1 U, आच्छद् 10, अंतर्धा, संवृ 5 U. **-off,** निवार्, निवृत् c., निरुध्, प्रति-वि-हन् 2 P, प्रतिकृ, व्यप-ऊह् 1 U, परिह्र 1 P; (*v. i.*) निवृत्, विरम्; *See* **Cease. -on,** *See* **Keep** (*v. i.*) above; प्रवृत्, प्रारब्धं सं-पद् c. **-out,** व्यावृत् c., प्रतिषिध्; *See* **Exclude. -to,** अनुवृत्, अनुस् 1 P, अनुरुध् 4 A, परिरक्ष्, परिपा c. (पालयति); *See* **Keep** (*v. t.*) above. **-under,** वशीकृ, वशं नी 1 P, स्वायत्तीकृ. **-up,** प्रवृत् c., पा c.; (*v. i.*) जागृ 2 P; न दम् or श्रम् 4 P. **-er,** *s.* रक्षकः, पालकः, रक्षितृ *m.*, रक्षिन् *m.*, गोप्तृ *m.*, पः-पालः in comp. **-ing,** *s.* रक्षा, अवेक्षा, पालनं, गुप्तिः. 2 सादृश्यं, अविरोधः, संगति *f.*, आनुरूप्यं; 'in k. with' अनुरूप-संवादिन्-सदृश-योग्य-*a.*

Keep-sake, *s.* स्मृतिदानं; स्मराभिज्ञानं.

Keg, *s.* काष्ठभांडं.

Kelter, *s. See* **Order.**

Ken, *s.* गोचरः-रं, विषयः; नयनविषयः-पथः, बुद्धिविषयः. -*v. t.* दूरादालोक् 1 A, 10 or ईक्ष् 1 A or दृश् 1 P. 2 परि-ज्ञा 9 U, अवगम् 1 P.

Kennel, *s.* श्वशाला, श्वगृहं, कुक्करालयः. 2 श्वगणः. 3 जलमार्गः, प्रणालः-ली. -*v. i.* श्वगृहे वस् 1 P.

Kerchief, *s.* आवरणं, वेष्टनं, आभरणं, 'hand-k.' हस्तप्रवारकः, मस्तकः; 'neck-k.' ग्रीवावेष्टनं, कंठवस्त्रं.

Kernel, *s.* बीजं, गर्भः, अस्थि *f.*, अष्ठीला, फलबीजं-गर्भः, सारभूतं द्रव्यं. 2 मध्यः-ध्यं, गर्भः, उदरं, हृदयं, अभ्यंतरं. **-ly,** *a.* बीजाकार, बीजपूर्ण.

Kestrel, *s. See* **Castrel.**

Kettle, *s.* कटाहः, पिठरः-रं, स्थाली, उखा, कुंडं; 'k.-drum' भेरि-री *f.*, दुंदुभिः डिंडिमः.

Key, *s.* अंकुटः, कुंचिका, ताला, उद्घाटकः-कं. 2 व्याख्या, निर्वचनं, टीका; 'k.-hole' कुंचिकाछिद्रं; 'k.-stone' संधान-संयोगप्रस्तरः.

Kibe, *s.* पादस्फोटः, विपादिका.

Kick, *v. t.* पादेन-लत्तया-प्रह् 1 P or तड् 10 or आ-हन् 2 U, लत्ताप्रहारं कृ 8 U; पादं-पार्ष्णिं-खुरं-क्षिप् 6 P. -*s.* पाद-लत्ता-प्रहारः पादाघातः, पार्ष्णि-खुर-क्षेपः, खुराघातः.

Kid, *s.* छागशावः-शावकः, अजशिशुः, अजपोतः, छागशिशुः. 2 काष्ठभारः.

Kidnap, *v. t.* (बालकं-दासं) चुर् 10, अपहृ 1 P, or बलाद् हृ. **-per,** *s.* बालस्तेयकृत् *m.* **-ping,** *s.* बालस्तेयं, बालापहारः.

Kidney, *s.* वृक्कः-क्का, गुर्दः; 'k.-bean' मुद्गः, माषः, शिंबा, शिंबिकः-का.

Kill, *v. t.* हन् 2 P, व्यापद् c., मृ c., सूद् 10, निषूद्, नश् c., प्र-मी 9 U or c. (मापयति), हिंस् 7 P, तृह् 6, 7 P, वि-शस् 1 P, पंचत्वं-परलोकं गम् c. (गमयति) or नी 1 P; शद् c. (शातयति), नियत् c., नि-कृत् 6 P, अप-नी, क्षि 5 P or c. **-er,** *s.* हंतृ *m.*, घातकः, नाशकः, निषूदनः, अंतकः; gen. हन् or घातिन् in comp.; 'k. of Vritra' वृत्रहन्; 'k. of Madhu' मधुसूदनः. **-ing** *s.* हत्या, वधः, हननं, घातः, मारणं, नाशः, निषूदनं, हिंसा-सनं, आलंभः, विशसनं, व्यापादनं, प्रमापणं, निबर्हणं, निकारणं, विशारणं, प्रवासनं, परासनं, संज्ञपनं, निर्ग्रंथनं, निस्तर्हणं, क्षणनं, परिवर्जनं, निर्वापणं, प्रमथनं, क्रथनं, उज्जासनं, पिंजः, विशरः, उन्माथः.

Kiln, *s.* पाकपुटी, आपाकः.

Kimbo, *a.* वि-अव-भुग्न, वक्र, कुटिल.

Kin, *See* **Kindred;** 'of k.' सजातीय, सगोत्र. 'Kith and k. आप्ताः (pl.)

Kind, *a.* दयालु, सदय, कृपाकुल, कृपालु, अनुकंपिन्, सानुकंप, सकरुण, करुणात्मन्, दया-करुणा-शील, करुणार्द्र, दयार्द्र, स्निग्ध, कृपा-दया-घृणा-वत्, कारुणिक (की *f.*); प्रियकर (री *f.*), हित, प्रियैषिन्, हितैषिन्, हितकाम, हितबुद्धि, उपकार-पर-शील, उपकारिन्, सुहृदय, अनुकूल, सुशील, प्रसन्न, प्रीत. 2 मधुर, प्रिय; 'k. to the poor' दीनानुकंपिन्, दीनवत्सल; 'k. office' उपकारः; 'k. act'

सुकृतं; 'k. words' प्रियवचनं; 'speaking k. words' प्रियंवद, प्रियवादिन्; 'k. present' प्रीतिदानं. -s. जाति f., गणः, वर्गः. 2 विशेषः, भेदः, प्रकारः, जातिः, रूपं, विधा, in comp.; 'of many k. s' बहुविध; 'of various k. s' विविध, नानारूप-विध, नाना ind.; 'of this k.' एवंविध, एवंरूप; 'of all k. s' सर्वप्रकार; 'Jāti is a k. of flower' जातिः कुसुमविशेषः-भेदः. -ly, a. सौम्य, मृदु, कोमल, स्निग्ध, प्रिय. 2 अनुकूल; समानशील. -adv. सदयं, सकरुणं, दयया, कृपया, प्रीत्या, सस्नेहं, सानुकंपं, सानुग्रहं; प्रियं, हितेच्छया, सुशीलवत्, सुजनवत्; 'speaking k.' प्रियवादिन्; 'k. disposed' हितबुद्धि, अनुरक्त. -ness, s. प्रसादः, अनुग्रहः, कृपा, दया, अनुकंपा, करुणा, प्रीति f., स्नेहः, कृपालुता, दयालुता, हितेच्छा, कृपाशीलता, सुशीलं, सौजन्यं, प्रेमन् m. n., आनुकूल्यं. 2 उपकारः, उपकृत-ति f., प्रियं, सुकृतंतिः, हितं. -Kindliness, s. सौम्यता, स्निग्धता; सौजन्यं, सुशीलता.

Kindle, v. t. प्र-उत्-सं-दीप् c., इंध् 7 A, ज्वल् c., तप् 1 P or c. 2 उत्तिज् c., संधुक्ष् 10, प्रोत्सह् c.; प्रकुप् c., रुष् c.; 'with glances k. ed with anger' क्रोधेद्धैर्दृष्टिपातैः (Rat. 1). -v. i. ज्वल् 1 P, दीप् 4 A, तप् 4 A.

Kindred, a. सजातीय, सगोत्र, सनाभि, सवर्ण, सवंशीय, सकुल्य, संबंधीय. 2 समान, सम-तुल्य-गुण, सधर्मन्, अनुगुण. -s. बंधुता, ज्ञातित्वं, ज्ञातिभावः, सगोत्रता, सजातित्वं, संबंधः, सपिंडता. 2 (Relatives) बंधवः, ज्ञातयः, बांधवाः, सगोत्राः, सकुल्याः, गोत्रजाः, संबंधिनः (pl.); बंधुजनः, बंधु-ज्ञाति-वर्गः, बंधु-बांधव-गणः.

Kine, s. pl. of **Cow,** q. v.

Kinematics, s. गतिशास्त्रं.

King, s. राजन् m., नृपः, नरपतिः, नृपतिः, भूपतिः, भूपः, भूपालः, नरेंद्रः; and comp. of ईशः, अधीशः, पतिः, इंद्रः, पः, पालः, भृत् or भुज् with 'Man' and 'Earth,' q. v. अवनिपः, क्षोणिपालः, भूभृत, महीभुक्, क्षितिपतिः; 'supreme or great k.' महाराजः, अधिराजः, सम्राज्, अधीश्वरः, मंडलेश्वरः; 'k. of k. s' राजराजः, राजाधिराजः, सार्वभौमः, चक्रवर्तिन् m. 'k. of beasts' मृगेंद्रः, मृगाधिपः, पशुपतिः; 'k.-craft' राजनीति f., -नयः, राज्यचातुर्यं; 'k.'s-evil' गंडमाला. -dom, s. राज्यं, राष्ट्रं, विषयः. 2 आधिपत्यं, ऐश्वर्यं, प्रभुत्वं, स्वामित्वं. 3 जाति f., वर्गः, गणः; 'animal k.' प्राणिवर्गः-जातिः. -less, a. अराजक, अनायक, राज-नृप-हीन. -like, -ly, a. राजकीय. 2 राजानुरूप, राजयोग्य, राजार्ह, राजसदृश (शी f.), नृपोचित, राज in comp. -ship, s. राजत्वं, प्रभुत्वं, ऐश्वर्यं, आधिपत्यं, नृपत्वं, राजपदं, राजाधिकारः.

Kinsfolk, *See* **Kindred** (s.).

Kinsman, s. बंधुः, बांधवः, ज्ञातिः, सकुल्यः, सजातिः-तीयः, सगोत्रः, सनाभिः, गोत्रजः, बंधुजनः.

Kirk, s. *See* **Church.**

Kismet, s. *See* **Fate.**

Kiss, v. t. चुंब् 1 P, निंस् 2 A; 'k. the lip' अधरं पा 1 P, अधररसं पा; 'k. on the head' शिरसि आ-समा-उपा-घ्रा 1 P. -s. चुंबनं, चुंबितं, अधरपानं. -er, s. चुंबकः.

Kit, s. उपकरणसमुदायः, उपस्करः, उपकरण-सामग्री, संभारः. 2 महाकुपी. 3 लघुसारंगी.

Kitchen, s. महानसं, रसवती, सूदशाला, पाकशाला-स्थान-गृहं; 'k.-garden' शाकशाकिनं, शाकशाकटं, शाकवाटिका; 'k.-maid' पाकचेटी; 'k.-work' पाककार्यं, पाकनिष्पत्ति f.; 'superintendent of the k.' पौरोगवः.

Kite, s. चिल्लः-ल्ला, आतापि(यि)न् m. 2 चिल्लाभासः, चिल्लासदृशं क्रीडनकं.

Kitten, s. मार्जारशावः-वत्सः-शिशुः.

Kittle, a. संशयस्थ, संदिग्ध. -v. t. कुतकुतयति (D.).

Kleptomania, s. चौर्यरुचि f.

Knab, v. t. दंश् 1 P, दंतैः ग्रह् 9 U or धृ 1 P.

Knack, s. कौशलं, चातुर्यं, वैदग्ध्यं, पाटवं; हस्त-कौशलं-लाघवं; *See* **Skill.** 2 क्रीडनकं, क्रीडावस्तु-द्रव्यं.

Knag, s. ग्रंथिः, पर्वन् n. 2 **Peg,** q. v. -ged, -gy, a. ग्रंथिल, पर्ववत्.

Knap, s. **Knob,** q. v. 2 उन्नतभूभागः, उत्सेधः. -v. i. **Snap,** q. v.

Knar, Knarl, s. काष्ठग्रंथि f.

Knave, s. धूर्तः, कितवः, जाल्मः, वंचकः, शठः, प्रतारकः, कूटकारः, दांभिकः. -ish, a. धूर्त, कितव, शठ, जाल्म, वंचक, प्रतारक, धूर्तशील, कपटिन्. -ishly, adv. सकपटं, सव्याजं, शठवत्, धूर्ततया. -ishness, -ry, s. धूर्तता, शाठ्यं, कैतवं, माया, व्याजः, छलं, कपटं.

Knead, v. t. (कराभ्यां) मृद् 9 P or c., संपीड् 10, चूर्ण् 10, पिष् 7 P. -ing, s. मर्दनं, पीडनं; 'k.-trough' द्रोणि-णी f.

Knee, s. जानु n., ऊरुपर्वन् n., अष्ठीवत् m. n., ऊरुसंधिः; 'go or fall on the k. s' जानुभ्यां (अवनौ) गम् or पत् 1 P; 'k.-deep' जानुदघ्न (घ्नी f.), -द्वयस (सी f.), -मात्र (त्री f.); 'k.-pan' जानुफलकं.

Kneel, v. i. जानुभ्यां (अवनौ) गम् or पत् 1 P or नम् 1 P, (क्षितितले) जानुनी निधा 3 U or न्यस् 4 U or निविश् c. or नम् c.

Knell, s. प्रेतघंटा.

Knick-knack, s. क्रीडनकं, क्रीडाद्रव्यं-वस्तु.

Knife, *s.* कर्तरिका, छुरिका, छुरी, कृपाणी, कृपाणिका, असिपुत्री-पुत्रिका, शस्त्री, असिधेनुः-नुका.

Knight, *s.* सादिन् *m.*, योधः, भटः.

Knit, *v. t.* सं-,ग्रंथ् 9 P, सिव् 4 P, निषिव्. 2 संबंध् 9 P, संयुज् 7 U, 10, संश्लिष् c., व्यतिषंज् 1 P, संहन् 2 P; व्यतिषजति पदार्थान् (Mal. 1) 'k. s'objects together'; 'k. the eyebrows' भ्रुकुटिं बंध्, भ्रुवौ संकुच् 1 P or भिद् 7 P; *See* **Frown.** **-a.** ग्रथित, स्यूत, संश्लिष्ट, व्यतिषक्त; 'well-k.' संहत, सुसंहत, दृढसंधि. **-ting,** *s.* सूत्रश्लेषः-ग्रथनं; 'k.-needle' दीर्घसूचि-ची *f.*

Knob, *s.* पिंडः, गंडः; ग्रंथिः, पर्वन् *n.*, संधिः (in wood). **-bed, -by,** *a.* सपिंड, पिंडिन्, ग्रंथिल, सगंड.

Knock, *v. t.* समा-आ-हन् 2 U, तड् 10, प्रहृ 1 P; 'k. on the head' मस्तकं तड्, मस्तकाघातेन व्यापद् c.; (fig.) मोघीकृ 8 U, विफलीकृ, भंज् 7 P. **-v. i.** द्वारं तड् or प्रहृ. **-s.** आघातः, अभिघातः, प्रहारः, ताडनं, पातः, हति *f.*; 'k. with a stick' वेत्राघातः; 'k. with the fist' मुष्टिघातः- प्रहारः. **-against,** अभि-प्रति-आ-हन्, संघट्ट 1 A, अभिसं-पत् 1 P; 'k. ed her head against a rock' दृषदं शीर्षेण आजघ्ने. **-down,** नि-अव-पत् c., आघातेन-प्रहारेण-निपत् c. or भ्रंश् c. **-off,** सत्वरं-लघु-संपद् c. or साध् 5 P. 2 विरम् 1 P, निवृत् 1 A. **-out,** प्रहारेण निर्गम् c. (गमयति) or निः-सृ c. or बहिष्कृ 8 U; 'k. out the brains' मस्तिष्कं निष्पिष् 7 P. **-up,** खिद् c., आयस् c., अवसद् c., श्रम् c. or क्लम् c. (श्र-क्ल-मयति); (*v. i.*) श्रम् 4 P, क्लम् 1, 4 P, खिद् pass., अवसद् 1 P, ग्लै-म्लै 1 P; 'k. ed up by the journey' अध्वसंजातखेदः, नितांतं परिश्रांतः. **-er,** *s.* प्रहर्तृ *m.*, ताडयितृ *m.* 2 द्वाःस्थमुद्गरः, द्वारताडनी.

Knoll, *v. i.* घंटां वद् c. or तड् 10. **-s.** क्षुद्रपर्वतः, उन्नतभूभागः, वप्रः-प्रं.

Knot, *s.* ग्रंथिः, बंधनं, ग्रंथिका, बंधः, गंडः; (of garments) नीवि- वी *f.*; (in wood) पर्वन् *n.*, संधिः. 2 संधिः, संयोगः, संश्लेषः, संबंधः. 3 मंडलं, समूहः, गणः, वर्गः, संघः, चक्रः, निवहः. 4 (Of trees) षंडः, गुच्छः, स्तबकः, गुल्मः-ल्मं, स्तंबः, कांडः. **-v. t.** ग्रंथिं बंध् 9 P, ग्रंथ् 9 P, संश्लिष् c., 'k. ed hair' वेणी; 'k. ed wound' रूढग्रंथिः व्रणः (U. 2). **-ted, -ty,** *a.* ग्रंथिल, ग्रंथिमत्, पर्व-संधि-मय (यी *f.*), पर्ववत्. 2 विषम, गूढ, दुर्ज्ञेय, दुर्बोध, गहन, गूढार्थ; 'k. point ग्रंथिः, विषमपदं.

Know, *v. t.* ज्ञा 9 U, विद् 2 P, बुध् 1 P, अवगम् 1 P, अव-इ 2 P, अभि-ज्ञा, परिचित-*a.* भू 1 P. 2 अनु-भू, वि-भू c., उपलभ् 1 A, ग्रह् 9 U; 'how should a dependent k. of sincere happiness (pleasure)' परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः (Mu. 3). **-er,** *s.* ज्ञातृ *m.*, ज्ञानिन् *m.*, वेत्तृ *m.* ज्ञः-अभिज्ञः in comp. **-ing,** *a.* विज्ञ, ज्ञानिन्; gen. ex. by विद्, ज्ञ or अभिज्ञ in comp.; 'k. Dharma' धर्मविद्, धर्मज्ञः. **-ingly,** *adv.* ज्ञानपूर्वं, कामतः, बोध-मति-बुद्धि-पूर्वं, जानत्-*a.* with अपि. **-ledge,** *s.* (Act) ज्ञानं, परि-वि-ज्ञानं, बोधः-धनं, वेदनं, अवगमः, उपलंभः, उपलब्धि *f.* 2 (Learning) ज्ञानं, विद्या, विद्वत्ता, पांडित्यं, व्युत्पन्नता, वैदुष्यं. 3 अभिज्ञानं, परिचयः; 'spiritual k.' आत्मज्ञानं-विद्या, परमार्थज्ञानं, अध्यात्मविद्या, परमार्थः, ब्रह्मविद्या, परमार्थबोधः; 'acquiring k.' विद्यार्जनं, विद्यागमः, ज्ञानप्राप्ति *f.*; 'eager after k.' ज्ञानेप्सु, जिज्ञासु; 'thirst after k.' जिज्ञासा, ज्ञानलिप्सा, ज्ञानेच्छा; 'according to one's k.' यथाज्ञानं; 'for the right k. of words and their meaning' वागर्थप्रतिपत्तये (R. I. 1); 'without the k. of' अविज्ञाप्य, अनिवेद्य, अगोचरं-रेण, परोक्षं क्षे; 'with the k. of' गोचरं-रेण, प्रत्यक्षं, साक्षात्, समक्षं; 'to come to the k. of' श्रुति-कर्ण-पथं या-इ-2 P or गम् 1 P; 'k. is power' बुद्धिर्यस्य बलं तस्य (P. I. 8). **-Known,** *a.* ज्ञात, विदित, अवगत, बोधित, उपलब्ध, अनुभूत, विभावित. 2 ख्यात, विश्रुत, प्रसिद्ध, वि-प्र-ख्यात, विज्ञात; 'to make k.' वि-ज्ञा c. (ज्ञापयति), नि-आ-विद् c., बुध् c., 'to become k.' ज्ञा-प्रति-इ pass.; 'be it k. to your honor' एवमत्रभवंतो विदांकुर्वंतु; 'be it k.' ज्ञातं-विदितं-अस्तु; 'became k. by that name' तदाख्यया (भुवि) पप्रथे (R. XV. 101), तदाख्यां जगाम.

Knuckle, *s.* अंगुलिपर्वन् *n.*-संधिः-ग्रंथिः- पर्व; संधिः, ग्रंथिः. **-v. i.** वशीभू 1 P, वशं गम् 1 P or इ-या-2 P. **-ed,** *a.* संधि-पर्व-विशिष्ट, ग्रंथिल.

Knurl, *s.* ग्रंथिः, गंडः. **-ed,** *a.* ग्रंथिल.

Kosmos, *s.* विश्वं, जगत् *n*

L.

Label, *s.* पत्रं, अंकपत्रं, बीजकं, लेपपत्रं.–*v. t.* लेपपत्रं आसंज् c. or अनुबंध् 9 P.
Labial, *a.* ओष्ठ्य.
Labio-dental, *a.* दंतो(तौ)ष्ठ्य.
Labor (Labour), *s.* श्रमः, परिश्रमः, प्र-आ-यासः, क्लेशः, कष्टं, दुःखं 2 उद्यमः, उद्योगः, व्यापारः, व्यवसायः, चेष्टा, प्र-,यत्नः, उत्साहः. 3 प्रसूतिकालः-समयः, प्रसवकालः, प्रसवावस्था; 'pain of l.' प्रसूति-प्रसव-वेदना-यातना-व्यथा; 'bodily l.' व्रातं, देह-काय-क्लेश-आयासः-श्रमः; 'unpaid l.' विष्टि *f.*, आजूः; 'got by one's l.' स्वकष्टार्जित. –*v. i.* परिश्रमं-आयासं-कृ 8 U, श्रम् 4 P, प्र-,यत् 1 A, व्यव-सो 4 U, चेष्ट् 1 A, उद्यम् 1 P, प्रवृत् 1 A, आयस् 1, 4 P, व्रातं कृ, शरीरायासं कृ. 2 खिद्-क्लिश्-पीड् pass., व्यथ् 1 A. 3 प्रसवावस्थायां वृत्, (आसन्नप्रसवा or प्राप्तप्रसववेदना सा स्त्री); 'l. under' बाध्-अभिभू- आक्रम्-पीड्-उपहन्-pass., 'l. ing under hundreds of anxieties' चिंताशतैर्बाध्यमान-अभिभूत; अतिभाराक्रांत &c.; 'l. ing under a disease' रोगपीडित, रुजार्त.–*v. t.* महाश्रमेण-प्रयत्नेन-साध् 5 P or सं-पद् c. or क्लृप् c. or वि-धा 3 U or कृ or अनु-ष्ठा 1 P. 2 कृष् 6 U. –**ed,** *a.* श्रम-यत्न-कष्ट-सिद्ध, यत्न-श्रम-पूर्व, प्रयत्नकृत. –**er,** *s.* कृतश्रमः, कर्मिन् *m.*, व्यवसायिन् *m.*, कार्मः. 2 कर्मकरः, कर्मकारः, भृतकः, वैतनिकः, भृति-भरण्य- भुज् *m.* 3 कृषकः, कृषीवलः; *See* **Farmer.** –**Laborious,** *a.* श्रम-आयास-कष्ट-साध्य, कष्ट-आयास-प्रद, पीडाकर (री *f.*), दुःखसाध्य, कष्ट. 2 आयासिन्, कृतश्रम, श्रम-उद्योग-कर्म-शील, उद्यमिन्, उद्योगिन्, सोद्यम, सोद्योग, सोत्साह; *See* **Industrious.** –**ly,** *adv.* श्रमेण, श्रम-आयास-पूर्वं, आ-प्र-यासेन, सयत्नं, सोद्योगं, सोद्यमं, सोत्साहं; कष्टेन, कृच्छ्रेण. –**ness,** *s.* श्रमसाध्यता. 2 उद्योगः, उद्यमः, व्यवसायः, उद्योगशीलता. –**Laboratory,** *s.* रसक्रियास्थानं, रससंस्कारशाला. 2 उद्योग-शिल्प-शाला-गृहं.
Labyrinth, *s.* अतिगहनः प्रदेशः, दुस्तरं or सुगहनं स्थानं, अशक्यनिर्गमः प्रदेशः, गहनं. –**ian,** *a.* गहन, सुदुस्तर.
Lac, *s.* ला(रा)क्षा, अलक्तः-क्तकः, जतु *n.*, यावः, द्रुमामयः. 2 लक्षं.
Lace, *s.* सूत्रं, तंतुः, गुणः. 2 सूत्रजालं, जालाभरणं, जालरूपं, वस्त्राभरणं. –*v. t.* सूत्रेण बंध् 9 P, or संयुज् 7 U, 10 or संश्लिष् c. 2 जालाभरणैः भूष् 10 or अलं-कृ 8 U.
Lacerate, *v. t.* दॄ 9 P, 10, निर्भिद् 7 P, व्यवच्छिद् 7 P, वि-पट् 10, कृत् 6 P; *See* **Tear.** –**ion,** *s.* विदारः-रणं, निर्भेदः, विपाटनं. 2 भेदः, छिद्रं, संधिः.
Laches, *s.* कालातिपातः, कालक्षेपः; उपेक्षा.
Lachrymal, *a.* अश्रुप्रवाहिन्, अश्रूत्पादिन्. 2 अश्रुसंबंधिन्.–**Lachrymatory,** *s.* अश्रुपात्रं भाजनं.–**Lachrymose,** *a.* सास्र, बाष्पाकुल.
Lack, *v.* न धा 3 U or भू 1 P or भृ 3 U; gen. ex. by हीन, रहित, वर्जित, शून्य in comp., or अ or निर् pr.; 'l. s wisdom' निर्बुद्धिः, अज्ञानः, बुद्धिहीनः, &c. –*s.* अभावः, हीनता, न्यूनता, विरहः, शून्यता. 2 प्रयोजनं; 'l.-lustre' निष्प्रभ, अतेजस्, मंदच्छाय, मलिनकांति; 'l.-brain' निर्बुद्धिः, मतिहीनः, मूढः, मूर्खः.
Lack-a-day, *interj.* अहो, हंत, हा, अहह, बत.
Lack-a-daisical, *a.* ध्यानपर-मग्न, चिंताकुल, उत्कंठित, विषण्ण.
Lacker, Lacquer, *v. t.* लाक्षारसेन छद् 10, कुंकुमेन लिप् 6 P.
Lackey, *s.* चेटः, दासः, भृत्यः, पार्ष्णिग्राहः, पार्श्वानुचरः.
Laconic,-al, *a.* संक्षिप्त, लघु, अल्प-मित-शब्दक, अविस्तीर्ण, सांक्षेपिक (की *f.*); 'l. message' लघुसंदेशपदा सरस्वती. 2 अल्प-मित-भाषिन्. –**ally,** *adv.* संक्षेपेण, संक्षेपतः, अविस्तरेण, मितकथया. –**ism,** –**Laconism,** *s.* लाघवं; लघूक्ति *f.*, संक्षेपोक्तिः; मितवाक्य-भाषणं.
Lactary, *s.* क्षीरस्थानं, गोदुग्धस्थानं.
Lactation, *s.* क्षीर-दुग्ध-दानं.
Lacteal, Lactean, Lactious, *a.* क्षीरिन्, क्षीर-दुग्ध-मय (यी *f.*), पायस (सी *f.*). 2 अन्नरसवाहिन्.
Lactiferous, *a.* दुग्ध-क्षीर-वाहिन्.
Lactometer, *s.* दुग्धमापनयंत्रं, दुग्धमापनी.
Lad, *s.* बालः-लकः, बटुः, दारकः, कुमारः-रकः, शिशुः, किशोरः, माणवकः.
Ladder, *s.* नि(निः)श्रेणि-णी *f.*, निश्रयि-(य)णी, अधिरोहिणी, सोपानपथः, सोपान-परंपरा-पद्धति *f.*
Lade, *v. t.* *See* **Load.**
Lading, *s.* नौभारः, पोतस्थद्रव्यं.
Ladle, *s.* दर्वि-र्वी *f.*, कंबि-बी *f.*, खजाका; 'wooden l.' तर्दूः, दारुहस्तकः; 'sacrificial l.' स्रुवः-वा, स्रुच् *f.*, चमसः-सी. –**ful,** *s.* कंबि-दर्वी-पूरकं-मात्रं.
Ladrone, *s.* दस्युः, जाल्मः, कितवः.
Lady, *s.* (As a title) देवी; 'your or her ladyship' अत्रभवती, तत्रभवती, भवती. 2 गृहिणी, स्वामिनी, भार्या. 3 आर्या, वनिता, कुलांगना, कुलस्त्री, कुलवधूः, भाविनी, कुलजा; 'l.-bird,-fly,-cow' इंद्रगोपः, शक्रगोपः, इंद्र-शक्र-कीटः; 'l.-love' प्रिया, कांता,

प्रणयिनी, कामिनी, दयिता; 'l. 's maid' प्रसाधिका, पत्रपरिकल्पिका. -like, *a.* शिष्ट, सभ्य, सुविनीत, आर्यवृत्ति. 2 पेलव, कोमल, मृदु, सुकुमार.

Lag, *v. i.* मंदायते (D.), चिर(रा)यति (D.), विलंब् 1 A, मंदं मंदं चल्-चर् 1 P. -*s.* अंत्यजाः, हीनजनाः (pl.); हीनवर्णः. -*a.*, -**Laggard,** *a.* मंद, मंदकर्मन्, विलंबिन्, चिरक्रिय, मंदायमान.

Lagoon, *s.* अनूपः, कच्छः, कच्छभूः, जलसनाथः प्रदेशः.

Laic,-al, *a. See* under **Lay.**

Laidly, *a.* अप्रिय, जुगुप्सित, बीभत्स.

Lair, *s.* (श्वापदानां) आ-नि-लयः, शयनस्थानं, वासस्थानं, गुहा, बिलं.

Laity, *s. See* under **Lay.**

Lake, *s.* सरस् *n.*, कासारः, ह्रदः, सरसी, तडागः-गं, तटाकः-कं; पद्माकरः, सरोवरः, जलाधारः, जलाशयः.

Lamb, *s.* मेषशावः-त्रकः, अजाशिशुः, मेषवत्सः-पोतः, अविपोतः. -**kin,** *s.* क्षुद्रमेषशिशुः, अविपोतकः.

Lambative, *a.* लेह्य. -*s.* लेह्यं, अवलेहः-हं.

Lambent, *a.* इतस्ततः वेपमान, लोल, कंपमान, तरल, चंचल.

Lame, *a.* खंज, पंगु (गू *f.*), खोड-ल-र, विकलगति, श्यंग; 'l. of a leg' पादेन खंज. 2 (Fig.) दुर्बल, विकल, सच्छिद्र, न्यून. -**ly,** *adv.* खंजवत्. 2 विकलं. -**ness,** *s.* खंजता, पंगुता, गतिवैकल्यं. 2 वैकल्यं, दुर्बलता, न्यूनता, सच्छिद्रता.

Lamel, Lamella, *s.* कवचः, आवेष्टनं, पटलं.

Lament, *v.* विलप् 1 P, रुद् 2 P, आ-,क्रंद् 1 P, अनु-,शुच् 1 P, परि-देव् 1 A, परिदिव् 10 A, क्रुश् 1 P, वि-आ-अभि-° ; 'they l. ed his departure' तद्गमनमन्वशोचन्, तद्गमनमुद्दिश्य अक्रोशन्, &c. -**able,** *a.* शोच्य,शोचनीय, शोकविषय, शोकास्पदं, शोकार्ह. -**ation,** *s.* विलापः, रोदनं, परिदेवनानं, परिदेवितं, शोकः, शुच् *f.*, विलपनं, रुदितं, आ-वि-क्रोशः, आ-,क्रंदनं, क्रंदितं,. -**ed,** *a.* शोचित; 'the l. Krishna' शोकास्पदीभूतः or स्वर्ग-परलोक-वासी कृष्णः. -**er,** *s.* शोचकः, परिदेवकः.

Lameter, Lamiter, *s.* खंजः, पंगुः.

Lamina, *s* कवचः-चं, शल्कं, पत्रं, फलकः-कं. -**Laminated,** *a.* सपत्र, फलकिन्.

Lamp, *s.* प्र-,दीपः, दीपकः, दीपिका, दशाकर्षः, दोषास्यः; 'l.-black' कज्जलं, दीपकिट्टं; 'l. -light' दीपप्रभा-प्रकाशः; 'l.-stand' दीपवृक्षः-पादपः-आधारः.

Lampoon, *s.* निंदालेखः, अपगीतं, निंदार्थो लेखः. -*v. t.* लेखैः निंद् 1 P or आक्षिप् 6 P or अप-गै 1 P. -**er,** *s.* निंदकः, अपगायकः, आक्षेपकः.

Lanate,-ed, *a.* लोमश, लोमविशिष्ट.

Lance, *s.* प्रासः, कुंतः, शूलः-लं, शल्यं, शक्ति *f.*, तोमरः. -*v. t.* प्रासेन व्यध् 4 P or निर्भिद् 7 P. -**er,** *s.* प्रासिकः, कौंतिकः, शाक्तीकः, शक्तिधरः-ग्रहः, शूलधरः. -**ing,** *s.* (gums) लेखनं.

Lancet, *s.* शलाका.

Lanch, *v. t. See* **Cast.**

Lancinate, *See* **Lacerate, Tear.**

Land, *s.* (Opposed to sea) स्थलं; 'proceeded by l.' प्रतस्थे स्थलवर्त्मना (R. IV. 60); 'the way by l.' स्थलमार्गः-वर्त्मन् *m.* 2 भूः,भूमि *f.*, प्रदेशः, विषयः, राष्ट्रं. 3 मृद् *f.*, मृत्तिका. 4 क्षेत्रं, क्षेत्रभूमिः, 'arable l.' कृष्ट-सीत्य-भूमिः; 'barren l.' मरुः, मरुस्थलं-ली, धन्वन् *m.*; 'marshy l.' कच्छभूः, अनूपभूमिः; 'waste or fallow l.' खिला-अप्रहता-भूमिः; 'gift of l.' भूमिदानं; 'l.-animal' स्थलचरजंतुः, भूमिचरजंतुः; 'l.-fight' स्थलयुद्धं; 'l.-force' स्थलसैन्यं, स्थलयोधाः; 'l.-holder' भू-क्षेत्र स्वामिन् *m.*, क्षेत्रपतिः; 'l.-lord,-lady' भूक्षेत्र-स्वामी-मिनी, गृहपतिः, गृहेश्वरः-री. 'l.-locked' भूवेष्टित, भूमिपरिगत; 'l. lotus' स्थलारविंदं, स्थलकमलिनी, 'l.-mark' सीमाचिह्नं, स्थल-भूमि-सीमा, सीमालिंगं; 'l. owner' भूस्वामी, क्षेत्रपतिः-स्वामी; 'l. scape' नयनगोचरीभूतः भूप्रदेशः or भूभागः दृष्टिगत-दृष्टिगोचर-प्रदेशः; भूभागः, प्र-,देशः 'l.-tax' भू-क्षेत्र-करः; 'l.-waiter' शौल्किकः. -*v. t.* (पोतात्-नावः) अवतॄ c., अव-रुह् c. (रोपयति); उत्तॄ c., स्थले निविश् c. -*v. i.* अवतॄ 1P, अवरुह् 1 P, उत्तॄ, निविश् 6 P. -**ed,** *a.* अवतीर्ण, नौकावरूढ, नौकोत्तीर्ण. 2 भूमिसंपन्न, क्षेत्रवत्, भूमिधन; भू in comp.; 'l. property' भूमिद्रव्यं, भूमिः, क्षेत्रं, स्थावरद्रव्यं; 'l. proprietors' भूस्वामिनः. -**ing,** *s.* उत्तरणं; l.-place' तरस्थानं, तरः, तरणस्थानं, घट्टः-ट्टी.

Lane, *s.* संकट-संबाध-पथः-मार्गः, कुपथः.

Language, *s.* भाषा, वाणी, वाच् *f.* 2 वचनं, वचस् *n.*, वाक्यं, उक्ति *f.*, व्याहारः, निगदः, भाषणं, भाषितं, आलापः, भारती. 3 भाषासरणि-पद्धति *f.*, वाग्व्यापारः; वचोविन्यासः; 'abusive l.' वाक्पारुष्यं, खलोक्तिः, आक्षेपवचः; आक्षरणं; 'dignity of l.' वचसां प्रौढता.

Languid, *a.* परि-,म्लान, क्लांत, ग्लान, लुलित, अवसन्न, शिथिल, विषण्ण,खिन्न, श्रांत, स्रस्त, विश्लथ, मुक्त; अलस, मंद, शिथिल-क्षीण-बल, श्लथांग-स्रस्तांग(गी *f.*); *See* **Droop.** -**ly,** *adv.* म्लान-ग्लान-वत्,सविषादं,अलसवत्,मंदं, क्लांतमनसा, मुक्तगात्रैः. -**ness,** -**Languor,** *s.* ग्लानि *f.*, म्लानि *f.*, अवसादः, शिथिलता,

क्लांति *f.*, ग्ला(म्ला)नता, शुष्कावयवता; मांद्यं, बलशैथिल्यं, गात्रभ्रंसः, अंगश्लथः, तंद्रा-द्रि *f.*, आलस्यं, जडता, आडथ्यं, कार्यविमुखता.

Languish, *v. i.* अवसद् 1 P, परि-,क्लम् 1, 4 P, परि-,म्लै-ग्लै 1 P, स्रंस् 1 A, गल् 1 P, शिथिलीभू 1 P, क्षि-विशृ-खिद्- pass.; ध्वंस् 1 A. 2 (With love) उत्सम् 4 P, उत्कंठ् 1 A, उत्सुक-*a.* भू. -ing, *a.* म्लायत्, क्षीयमाण, स्रंसिन्, शुष्क. 2 उत्सुक, उत्कंठित, कामालस; 'with her l. looks' अलसेक्षणा, कामालसदृष्टिः, कामार्द्रदृष्टिः. -ingly, *adv.* अवसादेन, अलसवत्. 2 सोत्कंठं, सोत्सुकं; कामालसदृष्ट्या. -ment, *s.* अवसादः, ग्लानता; *See* **Languor.** 2 औत्सुक्यं, उत्कंठा, उत्सुकता.

Laniary, *s.* घात-वध-स्थानं. 2 चर्वणदंतः अग्रदंतः

Lanier, *s.* चर्मबंधः, वरत्रा

Laniferous, *a.* रोमोत्पादिन्, लोमोद्भवकारिन्.

Lank, *a.* कृश, क्षाम, क्षीण, क्षीणमांस-शरीर; *See* **Lean.** 2 दीर्घतनु, दीर्घदेह. 3 श्लथ, शिथिल. -ness, *s.* कृशता, कार्श्यं, क्षामता, &c. -y, *a.* कृशदीर्घ, दीर्घक्षाम.

Lantern, *s.* प्रच्छन्नदीपः, सावेष्टनो दीपः, आवृतदीपिका; दीपः, दीपिका; 'l.-jawed' क्षीणवदन.

Lanuginous, *a.* लोमश, लोममय (यी *f.*).

Lap, *s.* उत्संगः, अंकः, क्रोडं. 2 अंचलः-लं; वस्त्रांतः, दशाः-वस्तयः (pl.); 'to place on the l.' क्रोडीकृ 8 U. -*v. t.* पुटीकृ, व्यावृत् c. 2 आ-परि-वेष्ट् 1 A or c.; अवगुंठ् 10, आ-परि-वृ 5 U, कोशे नि-धा 3 U. 3 लिह् 2 U, आ-अव-सं°; आ-स्वाद् 1 A; 'l.-dog' अंके पालनीयः कुक्कुरः; 'l. ful' अंकपूरणं-कं.

Lapidarious, *a.* शिला-प्रस्तर-मय (यी *f.*).

Lapidary, *s.* मणिकारः, रत्नाजीवः. 2 रत्नमणि-च्छिद् *m.*

Lapis-Lazuli, *s.* वैदूर्य, असितोपलः, नीलोपलः.

Lappet, *s.* *See* **Lap** (2).

Lapse, *s.* क्रमः, गति *f.*, प्रवाहः, प्रवृत्ति *f.*, अत्ययः. अतिक्रमः; 'after a l. of time' अथ दिनेषु गच्छत्सु, कालक्रमेण, गच्छता कालेन. 2 स्खलितं, प्रमादः, भ्रमः. 3 स्खलनं, पातः, भ्रंशः, च्युति *f.*, पतनं. -*v. i.* क्रमशः या 2 P or भ्रम् 1 P or सृप् 1 P; शनैः शनैः अति-इ 2 P or अतिक्रम् 1 U, 4 P. 2 भ्रंश् 1 A, 4 P, च्यु 1 A, पत् 1 P, विचल् 1 P, व्युत्क्रम्. 3 स्खल् 1 P, प्रमद् 4 P, भ्रम् 1, 4 P. 4 संक्रम्, अपवृत् 1 A. -ed, *a.* पतित, भ्रष्ट, &c. 2 परहस्तगत, संक्रांत, अपवृत्त; 'a l. suit' नियतवेलातीतं कार्यं.

Lapwing, *s.* टिट्टिभः-भकः, कोयष्टिकः

Lar, *s.* कुल-गृह-देवता.

Larboard, *s.* नौवामभागः.

Larceny, *s.* चौर्यं, स्तेयं; *See* **Theft**.

Lard, *s.* शूकरवसा-मेदस् *n.* 2 शूकरमांसं, वल्लूरं. -*v. t.* शूकरमेदसा पृ 3 U or c. 2 वि-सं-मिश्र् 10. 3 आ-प्यै c.; पुष् 1, 9 P or c.

Larder, *s.* भक्ष्यमांसागारं, भोजनागारं.

Large, *a.* (In size) विशाल, पृथु, बृहत्, स्थूल, विपुल, महत्, गुरु, उरु, पृथुल, आयत, विस्तीर्ण. 2 (Of l. body) महाकाय, स्थूल-विकट-शरीर, पृथु-बृहत्-शरीर; पीन, पीवर. 3 (In number) महत्, गुरु, पुष्कल, विपुल, प्रभूत, प्रचुर, बहु, बहुल, भूरि, 'of l. soul' महात्मन्; 'of l. nature' उदारधी, महात्मन्, अकृपणचेतस्. 4 (In age) वृद्ध, वयोधिक; 'larger boy' वर्षीयान् बालः; 'at l.' अपराधीनं, स्वेच्छया, स्वेच्छाचारेण, निर्यंत्रणं, निरवग्रहं, निरवरोधं. 2 सविस्तरं, विस्तरेण, विस्तरशः. 3 पूर्णतया, साकल्येन. -ly, *adv.* बहु, भूरि, अतीव, विपुलं, प्राचुर्येण, सु-अति-pr. -ness, *s.* स्थूलता, बृहत्त्वं, वैपुल्यं, प्राचुर्यं, बहुत्वं, बाहुल्यं; महाकायता, शरीरबृहत्त्वं, पीनता, पीवरता. 2 आयामः, विस्तारः.

Largess, *s.* दानं, वितरणं, पारितोषिकं, उपायनं, उपहारः; *See* **Gift.**

Lark, *s.* भा(भ)रद्वाजः, व्याघ्राटः, भारयः.

Larum, *s.* आसन्नभयसूचना-घोषणा.

Larva, *s.* कीटः, कीटडिंभः.

Larynx, *s.* कंठनालः-ली, कृकः.

Lascar, *s.* नाविकः, पोतवाहः.

Lascivious, *a.* कामुक, कामिन्, रतार्थिन्, कामासक्त, रतिसुखासक्त, भोगासक्त, लंपट, स्त्रीलंपट, कामप्रवण; *See* **Lustful.** 2 कामहेतुक, काममूलक. -ly, *adv.* कामुकवत्, लंपटवत्, भोगासक्त्या. -ness, *s.* कामुकत्वं, भोगासक्ति *f.*, रतासक्तिः, व्यवायेच्छा, लांपट्यं.

Lash, *s.* कशा, प्रतिष्कशः-षः, चर्मरज्जु *f.*, चर्मबंधः. 2 कशाघातः-ताडनं-प्रहारः. 3 वागसिः, परुषवचनं. -*v. t.* कशया आहन् 2 U or तड् 10 or प्रहृ 1 P. 2 वि-धू 5, 9 U, 6 P, विचल् c., इतस्ततः क्षिप् 6 P or चल् c. 3 वाग्बाणैः भिद् 7 P or तड्, वागसिना प्रहृ; तीक्ष्णं निंद् 1 P; 'l. ed into fury' वाग्बाणैः उत्तेजितक्रोधः; शिलातलप्रतिघातोत्पतत्फेनिलानामपां (Ka. 133); 'l. ed into foam by striking' &c. जर्जरितजलतरंगवितननीहारं (Mal. 9) 'so as to l. the water into snowy foam.' 4 रज्ज्वा बंध् 9 P; 'worthy of being l. ed' कश्य, कशार्ह.

Lass, *s.* तरुणी, कन्या, बाला, कुमारिका, दारिका.

Lassitude, *s.* खेदः, क्लमः, ग्लानि *f.*; *See* **Languidness.**

Lasso, *s.* पाशः, पाशबंधः-रज्जु *f.*

Last, *a.* अंत्य, अंतिम, अवर, अवरतम, चरम, पश्चिम; शेष-अंत-in comp. 2 गत, अतीत, चरम, पूर्व, भूत. 3 जघन्य, अधम, अपकृष्ट. 4

परम, उत्तम, अत्यंत; 'l. night' गतायां रात्रौ; 'the l. year' गत-अतीत-संवत्सरः, परुत् *ind.*; 'l. but one' उपांत्य, उपांतिक; 'l.-born' अवरज; 'at l.' अंते, अंततः; 'l. part' शेषभागः; 'l. part of the night' उत्तररात्रः, चरमयामः; 'l. half' उत्तरार्धः, पश्चार्धः, परार्धः, 'the year before l.' परारि *ind.*: 'to the l.' शेषं यावत्. -*adv.* अंते शेषे, अंततः, अवरं, चरमं, अवरतः. -*v. i.* अव-स्था 1 A, स्था 1 P; oft. by अवधिः in comp.; 'l. ing for many days' चिरस्थायिन्, एष ते जीवितावधिः प्रवादः (U. 1) 'will l. through life'; 'this will l. as food for four months' एतेन (अस्माकं) मासचतुष्टयस्य भोजनं भविष्यति; 'the bloom of youth l.s for a few days' कतिपयदिवसस्थायिनी यौवनश्रीः (Bh. II. 2). -**ing,** *a.* स्थायिन्, चिर-दीर्घ-कालस्थायिन्; अनपायिन्, नित्य, स्थिर, ध्रुव, अक्षय, शाश्वत (ती *f.*), अजर, चिरंतन (नी *f.*). -**ly,** *adv.* अंते, अंततः, चरमतः, शेषे, अवरतः.

Latch, *s.* अर्गला-लं, विष्कंभः, अर्गलाबंधः, तालकं, द्वारबंधनी; 'the postern door was on the l.' अर्गलानिरुद्धं पक्षद्वारं.

Latchet, *s.* पादुकाबंधनी.

Late, *a.* विलंबेन आगत or प्राप्त; कालातीत, वेलातीत, समयातीत, अतिक्रांतकाल, अतिकाल, अतीतकाल-समय. **2** अवसित, परिणत, अवसन्न. **3** नूतन, अचिर, प्रत्यग्र, अभिनव, आधुनिक (की *f.*), नातिपुराण, सद्यस्कालीन. **4** अतीत, गत, व्यतीत, भूत; प्राक्तन-पूर्वतन (नी *f.*), पौर्विक (की *f.*), 'at a l. hour of the day' परिणते दिवसे, अवसन्नप्राये अहनि; 'at a l. hour of the night' क्षीणभूयिष्ठायां क्षपायां; 'at a l. period of life' परिणते वयसि. -*adv.* विलंबेन, विलंबात्, वेलातिक्रमेण, अतिकालं-समयं, चिरेण, चिरात, चिरकालेन-लात्; 'to be l.' वेलातिक्रमं कृ 8 U चिर(रा)यति (D.); 'why are you l.' किमिति चिरायितं त्वया; 'l. in life' परिणतवयसि, *See* above; 'too l. in the day' अतिपराह्णे; 'too l. in the evening' अतिसायं. **2** अकाले, असमये. -**ly,** 'of late,' *adv* इदानींतने काले, नातिचिरात्प्राक्, आधुनिकसमये; अचिरं. -**ness,** *s.* कालातीतता, कालातिक्रमः; परिणामः, परिणति *f.* -**Later,** *a.* उत्तर, अपर, पर, उत्तरकालीन, पाश्चात्य. -*adv.* (on) उत्तरं, उत्तरोत्तरं, पश्चात, उत्तर-पर-काले.

Latent, *a.* नि-लीन, गूढ, छन्न, गुप्त, अदृष्ट, अप्रत्यक्ष, अप्रकाश, अप्रकट, अदृश्य, अंतर्हित, निभृत; 'a l. disease' धातुस्थः-शरीरांतर्गतः-रोगः.

Lateral, *a.* पार्श्वीय, पार्श्वस्थ, पार्श्विक (की *f.*). -**ly,** *adv.* पार्श्वभागे, पार्श्वतः, पार्श्वे.

Lath, *s.* सूक्ष्मकाष्ठ-दारु, तनुफलकः-कं.

Lathe, *s.* कुंदः-दं, भ्रमः-मि *f.*, चक्रं.

Lather, *s.* अंजनफेनः, मार्जनतैलफेनः.

Latifolious, *a.* पृथु-विशाल-पर्ण.

Latitude, *s.* अक्षः. **2** (Celestial) विक्षेपः. **3** विस्तारः, विस्तृति *f.*, प्रथिमन् *m.*, आयति *f.* **4** अनियंत्रणं, स्वातंत्र्यं, नियमोपेक्षा, नियमातिक्रमः, शैथिल्यं; 'degree of l.' अक्षांशः; 'l. of a planet' पतनं; 'parallel of l.' अक्षांशवृत्तं. -**Latitudinarian,** *a.* शिथिल, अनियंत्रण, निर्यंत्रण. -*s.* मतस्वातंत्र्यावलंबिन् *m.*, निर्बंधहीनः. -**ism,** *s.* मतशैथिल्यं, विचारस्वातंत्र्यं, अनियंत्रणं.

Latten, *s.* रीति *f.*, पित्तलं.

Latter, *a.* उत्तर, अपर, पर, अवर, अन्य, (*pron. a.*); पश्चिम, चरम, अंतिम; उत्तरोक्त, अपरोक्त; 'former and l.' पूर्वापरं; 'in the l. part of the day' पराह्णे. -**ly,** *adv.* अर्वाक्काले, अधुनातनकाले; *See* **Lately.**

Lattice, *s.* जालमार्गः, गवाक्षः, जालं, गवाक्षजालं, वातायनं; 'l.-work' जालकर्मन् *n.*

Laud, *v. t.* प्रशंस् 1 P, श्लाघ् 1 A, स्तु 2 U, कृत् 10, गुणं वर्ण् 10. -*s.* प्रशंसा, श्लाघा, स्तुति *f.*, गुण-वर्णना-कीर्तनं. -**able,** *a.* श्लाघ्य, स्तुत्य, प्रशस्य, श्लाघार्ह, प्रशंसार्ह, स्तवनोचित; *See* **Praise,-worthy.** -**ation,** *s.* प्रशंसनं, श्लाघनं. -**atory,** *a.* प्रशंसागर्भ, प्रशंसक, स्तुतिरूप, प्रशंसा-श्लाघा-स्तुति-मय (यी *f.*), प्रशंसाकर (री *f.*). -**er,** *s.* प्रशंसकः, स्तावकः.

Laugh, *v. i.* हस् 1 P. प्र-वि°; स्मि 1 A (l. gently); 'l. violently' उच्चैः हस्, अट्टहासं कृ 8 U, 'l. at' अव-उप-हस्, उपहासास्पदं मन् 4 A, अव-मन्; 'l. in the sleeves' अंतर्-निभृतं-हस्. -*s.*, -**ing,** -**Laughter,** *s.* हासः. हसनं, हास्यं, हसितं, वि-प्र°; स्मितं; 'a horse-l.' अट्टहासः, उच्चैर्हासः, प्र-अति-हासः; 'an inward l.' अंतर्हासः -**able,** *a.* हासकर (री *f.*), हास्यास्पदं, हास्य. -**er,** *s.* हासकः, हासिन् *m.* -**ing,** *a.* हास्यमुख (खी *f.*), स्मेरमुख, हास्यवदन; 'l.-stock' उपहासास्पदं, हास्यपात्रं. -**ingly,** *adv.* सहासं, विहस्य, सस्मितं.

Launch, *v. t.* (नावं जले) क्षिप् 6 P, मुच् 6 P or c.; प्रविश् c.; वह् c.; 'l. thy hundred-shafted bolt' मुंच शतशोऽशनिं (M. 5). **2** सहसा विसृज् 6 P or प्रक्षिप्, प्रास् 4 U. -*v. i.* जलं प्रविश् 6 P. -*s.* नौमोचनं or जलप्रवेशनं.

Laundress, Launder, *s.* रजकभार्या, निर्णेजकी. -**Launderer,** *s.* रजकः, निर्णेजकः.

Laundry, *s.* रजकगृहं, वस्त्रधावनशाला.

Laurel, *s.* नारलं (?); 'win l. s' ख्यातिं गम् 1 P, यशः अधिगम्; 'wear your l. s with modesty' लब्धेपि जये मा गर्वोध्मातो भूः; (भाग्येषु अनुत्सेकी भव S. 4).

Lava, *s.* आग्नेयोद्गारः.

Lave, *v. t.* क्षल् 10, धाव् 10; निज् 3 U; *See* **Wash.** **-atory**, *s.* धावनस्थानं. **-er**, *s.* धावन-प्रक्षालन-पात्रं, द्रोणी. **-ment**, *s.* वस्ति *m.f.*

Lavish, *a.* अतित्यागिन्, अतिव्ययिन्, व्ययशील-पर, अपरिमितव्यय, बहुप्रद, मुक्तहस्त. 2 अमित, अपरिमित, अतिरिक्त, अत्यधिक, अति pr. **-***v. t.* अपरिमितं व्यय् 10 (व्यययति), मुक्तहस्तेन दा 3 U or विसृज् 6 P or त्यज् 1 P or वितॄ 1 P or विश्रण् 10 or अप-चि 5 U or वृष् 1 P or अवा-कॄ 6 P; विक्षिप् 6 P. **-er**, *s.* अतिव्ययिन् *m.*, मुक्तहस्तः, व्ययपरः. **-ly**, *adv.* अतिव्ययेन, मुक्तहस्तेन, अपरिमितं, अत्यंतं. **-ment,-ness**, *s.* अति-अपरिमित-व्ययः, महाव्ययः, अतित्यागः, अत्युत्सर्गः, मुक्तहस्तत्वं, बहुप्रदत्वं.

Law, *s.* धर्मः, स्मृति *f.*, व्यवहारः, आचारः; धर्म-स्मृति-व्यवहार-शास्त्रं. 2 विधिः, शासनं, व्यवस्था, नियमः, नि-आ-देशः, नियोगः, सूत्रं, राजाज्ञा, चोदना, व्यवस्था-शासन-पत्रं, मर्यादा, स्थिति *f.*, कार्याकार्यनियमः, विधिनिषेधनियमः. 3 न्यायः, नीति *f.*, धर्मानुसारः, व्यवहारविधिः; 'a code of l. s' धर्मसंहिता, धर्म-स्मृति-शास्त्रं; 'criminal l.' दंडनीतिः-विधिः; 'matter recognizable by l.' व्यवहारविषयः-पदं; 'versed in l.' स्मृतिशास्त्रज्ञ, व्यवहारपंडित; 'common l.' स्मृतिः; 'breaking a l.' व्यवस्थातिक्रमः; 'going to l.' राजसभां-व्यवहारासनं-गत्वा विवाद-प्रशमनं-निर्णयः; 'to go to l.' विवद् 1 A, व्यव-हृ 1 P; 'against the l.' स्मृतिविरुद्धं; 'l.-breaker' व्यवस्थाभेदिन्-लंघिन्, नियमातिक्रामिन्; 'l.-giver' स्मृति-शास्त्रकारः, व्यवस्थापकः, शासितृ *m.*, विधि-न्याय-प्रवर्तकः; 'l.-suit' अर्थः, कार्यं, व्यवहारपदं; 'lay down a l.' व्यव-स्था c. (-स्थापयति). **-ful**, *a.* न्याय्य, शास्त्रविहित, शास्त्रोक्त, धर्म्य, यथान्याय, धर्मसंमत, धर्मशास्त्रानुरूप, शास्त्रसंमत, स्मृत्युक्त, व्यवहार-विधि-प्रोक्तः, विध्यनुसारिन्, अनिषिद्ध, धर्माविरोधिन्; 'l. wife' धर्मपत्नी; 'l. means' धर्मोपायः, न्यायोपायः. **-fully**, *adv.* विध्यनुसारेण, न्यायतः, धर्मेण, धर्मतः, धर्मानुसारेण, स्मृतिशास्त्रानुरूपं, यथान्यायं. **-fulness**, *s* न्याय्यता, धर्म्यता; धर्मानुसारः, धर्माविरोधः. **-less**, *a.* विध्यपेत, स्मृति-विधि-विरुद्ध, धर्म-न्याय-विरुद्ध, अन्याय्य, अधर्म्य. 2 (Of persons) अनियंत्रण, अनियत उच्छृंखल, स्वेच्छाचारिन्, स्वैरगति, अवश, कामचार, उद्दामवृत्ति; दुराचार, निर्मर्याद, अशिष्ट, आचार-धर्म-भ्रष्ट. **-lessly**, *adv.* अवशं, उच्छृंखलं, दुराचारवत्, धर्मविरोधेन, शास्त्रविरुद्धं. **-lessness**, *s.* कामवृत्ति *f.*, मर्यादातिक्रमः, अनाचारः, आचारभ्रष्टता, नियमातिक्रमः; स्वेच्छाचारः. **-Lawyer**, *s.* विधिज्ञः, न्यायनिपुणः, व्यवहारपंडितः, धर्मशास्त्रज्ञः, धर्मज्ञः, स्मृतिपारगः; अर्थिप्रत्यर्थिपक्षसमर्थकः.

Lawn, *s.* तृणभूमि *f.*, तृणावृता भूः, शाद्वलं स्थानं, सतृण-हरित-स्थलं. 2 क्षौमं, अंशुकं, दुकूलं.

Lax, *a.* शिथिल, श्लथ, स्रस्त, विगलित. 2 मृदु, कोमल, अतीक्ष्णदंड. 3 दुराचार, भ्रष्टचरित्र, धर्म-कर्म-भ्रष्ट; 'l. in bowels' मृदु-अबद्ध-कोष्ठ. **-***s.* अतिसारः, प्रवाहिका. **-ative**, *a.* सारक, रेचक. **-***s.* सारकं. **-ity,-ness**, *s.* शैथिल्यं, अतीक्ष्णता; अनाचारः, मर्यादातिक्रमः; इंद्रियासंयमः, &c.

Lay, *v. t.* धा 3 U, नि-आ°, न्यस् 4 U, निविश् c., स्था c. (स्थापयति); सम्-ऋ c. (अर्पयति), निक्षिप् 6 P, आरुह् c. (रोपयति); दा 3 U, धृ 1 P; क्रमेण स्था c. or नि-धा; प्रक्लृप् c., प्रयुज् 7 A, 10 (a plot, snare, &c.). 2 आ-स्तृ-स्तॄ 5, 9 U. 3 शम् c. (शमयति), प्र-उप-°; सांत्व् 10, स्थिरीकृ 8 U. 4 शी c.; निपत् c.; 'l. eggs' अंडमोक्षं कृ; अंडानि सू 2, 4 A; 'l. siege' रुध् 7 U, वि-ष्टंभ् 9 P; *See* **Besiege**; 'l. blame on' दोषं समारुह् c. or निक्षिप्; 'l. waste' उप-प्लु 1 A, उपद्रु 1 P, उद्-ध्वंस् c., निर्जनीकृ; *See* **Devastate**; 'a sinful action, though done by others, is laid at his doors' पापं कर्म च यत् परैरपि कृतं तत्तस्य संभाव्यते (Mr. 1); 'l. aside' अप-निर्-अस्, त्यज् 1 P, हा 3 P, उत्सृज् 6 P, उज्झ् 6 P; 'l. it aside for a while' मुहूर्तं तत् आस्तां-तिष्ठतु तावत्; (as dress &c.) उद्-वि-मुच् 6 P, अवतॄ c., अवरुह् c.; 'l. hands on' परामृश् 6 P, धृष् c.; 'laid upon him his hand' तं हस्तेन पस्पर्श or परामृशत्; 'l. hold of' धृ, ग्रह् 9 U; *See* **Catch**; 'l. the dust' धूलिं संसिच् 6 P or आ-हन् 2 U; 'l. open or bare' विवृ 5 U, आविष्कृ; स्फुटीकृ, वि-अंज् 7 P or c., स्पष्टी-प्रकटी-कृ, प्रकाश् c. **-before**, उपनि-अस्, उपक्षिप्, पुरो-नि-धा, प्रसृ c., नि-आ-विद् c. **-by**, सं-,रक्ष् 1 P, संचि 5 U. **-down**, न्यस्, निक्षिप्, नि-धा, न्यासीकृ. 2 शी c., निविश् c. 3 विसृज्, परि-,त्यज्, वि-हा. 4 (Oneself) संविश् 6 P, शी 2 A. 5 प्र-णी 1 P, वि-धा (rules &c.); 'l. down arms' युद्धाद्विरम् 1 P, शरणं व्रज् 1 P; 'l. down life' प्राणान् त्यज्. **-in**, संग्रह्, संचि, संरक्ष्. **-on**, पत् c., प्र-युज्, सम्-ऋ c. **-out**, विनि-युज् 7 A, 10, प्र-युज्,

व्यय् 10 (व्यययति). **2** परि-प्र-क्लृप् c., वि-न्यस् 4 U, विरच् 10, प्र-युज्, चिंत् 10; *See* **Contrive. 3** प्रसृ c., विस्तॄ c., दीर्घीकृ; प्रकाश् c., प्रकटीकृ 'l. oneself out'; चेष्ट् 1 A, प्रयत् 1 A, उद्यम् 1 A. **-to,** आ-रुह् c., निक्षिप्; *See* **Ascribe;** 'l. to a ship' नौगतिं रुध् or स्तंभ्. **-up,** नि-धा, रक्ष्, संचि; 'to be laid up,' शय्याग्रस्त-*a*. भू 1 P, उत्थातुं अक्षम-*a*. भू; 'laid up with fever' ज्वरेणोत्थातुमक्षमः. **-Lay,** *s.* गानं, गीतं, काव्यं. **2** आस्तरः-रणं, फलकः-कं. **-*a*.** सामान्य, साधारण (णी *f*.), पुरोहितभिन्न. **-man,** *s.* गृहस्थः, सामान्य-साधारण-जनः, अदीक्षितः, प्राकृतः. **-Laical,** *a.* गृहस्थिन्, गार्हस्थिक (की *f*.), पुरोहितभिन्न, अदीक्षित. **-Laity,** *s.* गृहस्थ-सामान्य-जनवर्गः, प्राकृत-साधारण-जनाः, पुरोहितभिन्नवर्गः.

Layer, *s.* स्तरः; आस्तरः-रणं, फलकः-कं. **2** **Twig,** q. v.

Lazar, *s.* कुष्ठिन् *m.*, श्वित्रिन् *m.*, कोठोपहतः, त्वग्रोगोपहतः; 'l.-house' कुष्ठिशाला, श्वित्र्यालयः.

Lazy, *a.* अलस, तांद्रिल, जड, मंद, मंथर, तंद्रालु, मंदगति. आलस्यशील, अनुद्योगिन्, उद्योगविमुख (खी *f*.), अव्यवसायशील, शीतक, अनुष्ण, तुंदपरिमृज. **-ly,** *adv.* अलसवत्, जडवत्, मंदं मंदं, जाड्येन. **-ness,** *s.* आलस्यं, मांद्यं, जाड्यं, जडता, तंद्रिका, तंद्रालुता, कार्यद्वेषः, अनुद्योगशीलता, उत्साहविमुखता, अलसशीलता.

Lea, *s.* *See* **Lawn** (1).

Lead, *s.* सीसं, सीसकं, नागं, योगेष्टं, वप्रं; 'red l.' सिंदूरं, नागसंभवं, रक्तचूर्णं, नागजं, नागगर्भं. **-s.** नायकत्वं, नेतृत्वं, अधिष्ठातृत्वं, मुख्यत्वं, अग्रगमनं-यानं, पुरःसरणं **-*v. t.*** नी 1 P, वह् 1 P, प्राप् c., गम् c. (गमयति) (all with two accusatives); आ-दा 3 A. **2** (Way) दृश् c., आ-निर्-दिश् 6 P. **3** अधि-ष्ठा 1 P, अध्यास् 2 A, प्रणी, आ-निर्-दिश्; पुरस्कृ 8 U; अग्रणीः-नायकः-अग्रेसरः-भू 1 P (with gen.); वसिष्ठाधिष्ठिता देव्यः (U. 1) 'led by Vasishtha' &c., दशरथस्य द्वारानधिष्ठाय (U. 4;) 'led by the demon' दानवं पुरस्कृत्य. **4** आकृष् 1 P, प्र-वि-लुभ् c., प्रवृत् c, प्रेर् c., प्रोत्सह् c, नी; मूढः परप्रत्ययनेयबुद्धिः (M. 1) 'has his mind led by the convictions of others.' **5** (Time) नी, गम् c., अतिवह् c., क्षै c. (क्षपयति), या c. (यापयति); 'led a dissolute life' विषयसुखनिरतो जीवितमत्यवाहयत्; 'l. ing a life above their station' स्वस्थानानुचितां-स्वस्थानातिरिक्तां-जीवयात्रां कल्पयंतः. **-*v. i.*** (On) अग्रे-पुरः-पुरतः-अग्रतः-भू or गम् 1 P or वृत् 1 A or स्था or चर् or सृ 1 P. **2** (To) (lit.) गम्, या 2 P; 'on the way l. ing to Chitrakúta' चित्रकूटयायिनि वर्त्मनि (U. 1). **3** (Cause) ex. by dat. of noun with or without भू, आवह्, उत्पद् c., जन् c. (जनयति); 'advice to fools l.s to their provocation' उपदेशो हि मूर्खाणां प्रकोपाय (भवति) (H. 3). **-ed,** सीसकयुक्त. **-en,** *a.* सीसकनिर्मित, **-er,** *s.* नायकः, नेतृ *m.*, मार्गदर्शकः, मार्गोपदेशकः (lit.); मुख्यः, मुख्यः, अग्रणीः, प्रमुखः, अधिपः, ईश्वरः, पतिः, अध्यक्षः, आधिपतिः, अधिष्ठातृ *m.* **2** पुरोगः-गमः, अग्रगः, अग्र-(ग्रे)सरः, पुरःसर, पुरोगामिन् *m.*; 'l. of an army' सेनानीः, चमूपतिः, योधाध्यक्षः, सेनानायकः; 'l. of a religious sect' गुरुः, आचार्यः. **-ership,** *s.* नायकत्वं, आधिपत्यं. **-ing,** *a.* अग्रग, पुरोगामिन्, पुरःसर, पुरोगम, प्राक्-अग्र-गामिन्. **2** अग्र, अग्र्य, मुख्य, उत्कृष्ट, प्रमुख, परम, उत्तम, प्रधान in comp. **3** (To) आवह, कर (री *f.*) in comp.; 'l. to happiness' कल्याणावह, कल्याणकर, कल्याणोदर्क. **-s.** नयः, नीति *f.*, नेतृत्वं; 'l.-strings' आलंबनसूत्राणि; 'hold or keep in l.-string,' आत्माधीन-*a*. कृ, स्ववशं नी, नियम् 1 P. **-Led,** *a.* नीत, प्रेरित, अधिष्ठित, &c.; 'l. by' ex. by पुरःसर, पुरोगम, प्रमुख, आदि in comp.

Lead-wort, *s.* पाठिन् *m.*, चित्रकः, वह्निसंज्ञकः.

Leaf, *s.* पत्रं, पर्णं, छदः, दलः-लं, पलाशं, छदनं; (of a book) पत्रं; (of a door) कपा(वा)टः-टं-टी, अररं-री; 'fallen l.' प्रपर्णं; 'faded l.' शीर्णपर्णं; 'to strip off the leaves' निष्पत्रीकृ 8 U. **-less,** *a.* निष्पत्र, अपर्ण, निष्पर्ण, निर्दल, पत्र-पर्ण-दल-हीन. **-let,** *s.* पत्रकं, सूक्ष्म-लघु-पत्रं. **-y,** पर्णावृत, पर्णमय (यी *f.*), बहुपर्ण, बहुपत्र-दल, सपत्र, सपर्ण, पर्णिन्.

League, *s.* संधिः, साहित्यं, संघातः, ऐक्यं, संयोगः, संघट्टनं, अन्योन्योपकारप्रतिज्ञा. **2** गव्यूति *f.* **-*v. i.*** संधा 3 U, पक्षीय-*a*. भू 1 P, संहन्-संयुज्-pass., संमिल् 6 P, संधिं कृ 8 U, संघट् 1 A; 'l. ed with the enemy' शत्रुपक्षे स्थित. **-ed,** *a.* कृतसंधि, संधित, संहत, संघातवत्, संयुक्त, कृतसंसर्ग, संसृष्ट, मिलित; 'having l.' संभूय, मिलित्वा. **-er,** *s.* संगिन् *m.*, संसर्गिन् *m.*, सह-संभूय-कारिन् *m.*

Leak, *s.* छिद्रं, रंध्रं, संधिः. **2** धारा, स्रवः, स्यंदः, द्रवः. **-*v. i.*** (अलक्षितं) स्रु 1 P; परिस्रु, रा 4 A, क्षर् 1 P, गल् 1 P, स्यंद् 1 A; आयुः परिस्रवति भिन्नघटादिवांभः (Bh. ii. 109) 'like water l. ing from a broken jar' &c. **-ing,** *s.* स्रवः, क्षरणं,

निस्यंदः, स्रयः. -y, *a.* छिद्रपूर्ण, स्रवणशील, सच्छिद्र, सरंध्र.

Lean, *a.* कृश, परि-, क्षाम-क्षीण, अवसन्न, तनु, क्षीणशरीर-मांस, कृशांग (गी *f.*); 'you are growing l.-er and l.-er day by day' अनुदिवसं परिहीयसेऽंगैः (S. 3): 'l. ness of body' शरीरसादः. -*s.* क्षाडुः, वल्लसा. -*v. i.* अव-लंब् 1 A, आ-सं-श्रि 1 U; 'l. ing on a mango stick' अवलंब्य चूतयष्टिं; मदलेखया दत्तहस्तावलंबा (Ka 206) 'l. ing on M.'s arm.' 2 पक्षं आश्रि or अवलंब्, प्रवण-*a.* भू 1 P. 3 आ-अव-नम् 1 P, नम्रीभू, बहिर्लंब्, तिरः-तिर्यक् लंब्. -*v. t.* उप-धा 3 U, निविश् c., न्यस् 4 U; वामहस्तोपहितवदना (S. 4) 'l. ing her face on her left hand'; also ex. by (*v. i.*). -**ing,** *a.* आलंबिन्, संश्रित, आनत; प्रवण, बहिर्लंब, प्रलंब, वक्र. -*s.* प्रवणता, सं-आ-श्रयः, आलंबनं. -**ness,** *s.* कृशता, कार्श्यं, क्षीणता, क्षामता, अव-,साद्, शोषः, शरीरशोषण.

Leap, *v. i.* प्लु 1 A, उत्-प्लु, वल्ग् 1 P: नृत् 4 P; 'l. down' अवतॄ 1 P, अवप्लु; 'l. up' उत्पत्, उत्प्लु; 'l. over' लंघ् 1 A, 10, अतिक्रम् 1 U, 4 P, अति-इ 2 P. -*s.* प्लुति *f.*, प्लुतं, प्लवः, वल्गितं, झंपः, प्लवनं; 'quick (deer's) l.' हरिणप्लुतं; 'going by l. s' प्लुतगति, प्लवग. -**ing,** *s.* प्लवनं, वल्गितं, प्लुतिः; 'l. over a period' मंडूकप्लुतिः.

Learn, *v. t.* शिक्ष् 1 A, अधि-इ 2 A, पठ् 1 P, अधिगम् 1 P, अभ्यस् 4 U; अभ्यासेन विद्यां लभ् 1 A or प्राप् 5 P. -*v. i.* ज्ञा 1 U, अवगम्, विद् 2 P, बुध् 1 P, उपलभ्, श्रु 5 P, गृहीतार्थ-*a.* भू 1 P; *See* **Know.** -**ed,** *a.* विद्वस् (दुषी *f.*), विपश्चित्, ज्ञानिन्, विद्या-विशिष्ट-संपन्न-वत्, कृत-उपात्त-विद्य पंडित, बुध, प्रा(प्र)ज्ञ; ज्ञानवत्, व्युत्पन्न, बहुश्रुत, सूरि, विद्यावृद्ध, साक्षर. 2 अधीतिन्, विचक्षण, विज्ञ, कुशल, निपुण, प्रवीण, चतुर; कोविद, ज्ञ, विद् in comp. 3 (Of books &c.) पांडित्यस्य सूचक, ज्ञानस्य गमक; 'a l. man' पंडितः, विपश्चित्, सूरिः, बुधः, &c.; 'l. in law' स्मृतिज्ञ, न्यायविद्. -**edly,** *adv.* पंडितवत्, प्रज्ञवत्, सज्ञानं, निपुणतया, सकौशलं. -**er,** *s.* शिष्यः, छात्रः, अध्येतृ *m.*, विद्यार्थिन् *m.* -**ing,** *s.* विद्या, विद्वत्ता, विद्वत्त्वं, ज्ञानं, पांडित्यं, व्युत्पत्ति *f.*, प्राज्ञता, विद्यासंपद् *f.* 2 (Act) अध्ययनं, शिक्षणं, अभ्यासः, विद्यार्जनं, विद्याप्राप्ति *f.*, ज्ञानागमः. 3 शास्त्रं, विद्या; 'sacred l.' श्रुति *f.*, निगमज्ञानं; 'he affects great l.' पंडितंमन्यः, पंडितायते (D.).

Lease, *s.* पट्टः, पट्टोलिका. -*v. t.* आविहितकालात् निरूपितमूल्येन दा 3 U or विसृज् 6 P.

Leasing, *s. See* **Falsehood.**

Leash, *s.* चर्मबंधः, चर्मरज्जु *f.* 2 त्रयं, त्रितयं.

Least, *a.* अणु, अल्प, स्तोक, अत्यल्प, अल्पिष्ठ, कनिष्ठ, स्तोकतम, अल्पतम, क्षोदिष्ठ; 'the l. sorrow' अणुरपि शोकः; 'the l. particle' लवः, लेशः, अणुः कणः. -*adv.* स्तोकं, अल्पिष्ठं, किंचित्, कियत्; 'in the l.' मनागपि, अल्पमपि, स्तोकांशेनापि, स्तोकमपि, लेशमपि, किमपि, किंचिदपि; 'at l.' ex. by अवर-*a.* in comp.; 'witnesses should be at l. three' त्र्यवराः साक्षिणो ज्ञेयाः (Y. II. 69); 'at l. 100 Rs.' शतावरा रूपकाः; oft. by तावत्, 'at l. once' सकृदपि तावत्.

Leather, *s.* परिष्कृतं चर्म; 'l.-bag' चर्मभस्त्रिका, चर्मप्रसेविका; 'l.-bottle' कुतू *f.*, 'a small l.-bottle' कुतुपः, 'l.-dresser' चर्मकृत्, चर्मकारः; 'l.-seller' चर्मविक्रयिन्. -**Leathern,** *a.* चर्मकृत-निर्मित, चर्ममय (यी *f.*), चर्म in comp.

Leave, *s.* अनुज्ञा-ज्ञानं, अनुमति *f.*, अनुमोदनं 2 आमंत्रणं, आपृच्छनं; 'to take or ask l. of' आमंत्र् 10 A, आपृच्छ् 6 A; *See* **Adieu;** 'to give l.' अनु-ज्ञा 9 U, अनु-मन् 4 A, अनुमुद् 1 A. -*v. t.* त्यज् 1 P, हा 3 P, उत्सृज् 6 P, उज्झ् 6 P, रह् 1 P 10, परिहृ 1 P, वर्ज् 10, निर्-,मुच् 6 P. 2 निर्गम् 1 P, अपगम्, अप-इ-या 2 P, अपसृ 1P, अपक्रम् 1 U, 4 P, (all with abl.). 3 मृत्युपत्रेण दा 3 U; 'estate left (after death)' रिक्थं. 3 विरम् 1 P, निवृत् 1 A (with abl.); मुच्, त्यज्, अपास् 4 P: oft. ex. by स्था 1 P, आस् 2 A; 'l. it now' तिष्ठतु आस्तां तदधुना. 4 निक्षिप् 6 P, न्यस्, सम्-ऋ c. (अर्पयति); 'l. everything to him' सर्वं तदधीनं कुरु. 5 शिष् 7 P, or c., अव-परि°; उद्-वृत् c., 'nothing was left' न किमप्यवशिष्टं; 'to be left' शिष् pass.; 'we being left behind' अस्मास्ववशिष्टेषु (S. 2). -*v. i.* निर्गम्, अप-या, विरम्, &c. -**for,** प्र-स्था 1 A (with acc.). -**off,** विरम्, निवृत्, त्यज्; *See* above. 'the peacock left off dancing' परित्यक्तनर्तनो मयूरः (S.4). 'when it left off raining' शांते पानीयवर्षे ((H. 3). -**out,** वृज्, परित्यज्. -**Leavings,** *s.* शेषः-षं, परि-अव°; शिष्टं, अव-परि°, शेषभागः-खंडः, उद्धृतं, उच्छिष्टं. 2 मलं; 'l. of food' शेषान्नं, भक्षित-भुक्त-शेषः-षं, भुक्तावशिष्टं, उच्छिष्टं, भुक्तोज्झितं; 'one who eats l.' शेषभोजिन्, उच्छिष्टाशनः.

Leaven, *s.* किण्वं, मग्नहुः, कारोत्तरः, मंडः-डं. -*v. t.* कुष् c. (कूषयति); रंज् c.

Leacher, *s.* लंपटः, कामासक्तः, कामुकः, स्त्रीपरः-लंपटः, सुरतार्थिन् *m.* **-ous,** *a.* कामुक, कामासक्त, सुरतार्थिन्, स्त्रीपर; *See* **Lustful. -ously,** *adv.* लंपटवत्, कामुकवत्. **-ousness,-y,** *s.* **Lust,** q. v.

Lection, *s.* पाठः. **2** पाठांतरं, पाठभेदः.

Lecture, *s.* प्रपाठः, व्याख्यानं, शासनं, आख्यापनं; 'it is easy to read l. s to others' सुखमुपदिश्यते परस्य (Ka. 156) (*cf.* परोपदेशे पांडित्यं). **2** वाग्दंडः, निर्भर्त्सनवाक्यं. -*v.* पठ् c., अधि-इ c. (अध्यापयति), शास् 2 P, उपदिश् 6 P. **2** निर्भर्त्स् 10 A, निंद् 1 P, गर्ह् 1, 10 A. **-er,** *s.* पाठकः, अध्यापकः, शिक्षकः, उपदेशकः; प्रवक्तृ *m.*, वादिन् *m.*, व्याख्यातृ *m.*

Ledge, *s.* कटकः-कं, कूटं. **2** शिला, शिलाफलकं. **3** फलकः-कं, आस्तरः. **4** आलि-ली *f.*, आवलि-ली *f.*

Ledger, *s.* (बृहत्) गणनापुस्तकं.

Lee, *s.* निर्वातस्थानं-देशः. **2** वाताभिमुखी दिक्. **-ward,** *adv.* अनुवातं, वातानुलोमं.

Leech, *s.* रक्तपा, जलौ(लू)का, जलौकसः (*f.* pl.); जलसर्पिणी, रक्तपायिनी, जलजंतुका. **2** भिषज् *m.*, वैद्यः, चिकित्सकः.

Leek, *s.* कंदः-दं.

Leer, *s.* कटाक्षः, दृष्टिविक्षेपः, दृक्पातः, अर्धवीक्षणं, साचिविलोकितं, अपांगदर्शनं. **2** कुस्मितं. -*v. t.* कटाक्षेण ईक्ष् 1 A or दृश् 1 P, साचि-तिर्यक्-विलोक् 1 A, 10. **2** कुस्मि 1 A. **-ing,** *a.* अपांगदर्शिन्, साचि-तिर्यक्-दृष्टि. **2** कुस्मेर.

Lees, *s.* मलं, किट्टं, उच्छिष्टं.

Left, *a.* वाम, सव्य, दक्षिणेतर; 'l.-handed' वामहस्त, सव्यसाचिन्; 'to the l.' वामेन, वामतः.

Leg, *s.* जंघा, प्रसृता, पादः; 'swelling of the l.' श्लीपदं; 'having a swelled l.' कुंभपादः-पदी; 'long-l. ed' दीर्घपाद्-द्, दीर्घजंघ. **-Legging,** *s.* जंघारक्षणं.

Legacy, *s.* उत्तरदानं, मृत्युलेखार्पितदानं.

Legal, *a.* धर्म्य, न्याय्य, स्मार्त (र्ती *f.*), व्यवहारानुरूप, न्यायानुसारिन्, शास्त्रविहित, शास्त्रोक्त, स्मृत्युक्त. धर्म-न्याय-अनिषिद्ध; *See* **Lawful. 2** स्मृति, धर्म, व्यवहार, in comp.; 'l. proceeding' व्यवहारः; 'wrong l. opinion' अव्यवस्था; 'written l. opinion' पट्टोलिका. **-ity,** *s.* न्याय्यता, धर्म्यता, धर्म-शास्त्र-अनुसारः; **2** कर्ममार्गसेवा, कर्मनिष्ठा. **-ize,** *v. t.* व्यवस्था c. (स्थापयति), शास्त्रसंमत-*a.* कृ U, कृ with (*a*). **-ly,** *adv.* धर्मेण, न्यायेन धर्मतः, न्यायतः; यथाधर्मं, यथान्यायं, धर्मानुसारेण.

Legate, *s.* दूतः, प्रणिधिः. **-Legation,** *s.* दूत-धर्मः-क्रिया, दौत्यं.

Legatee, *s.* मृतारिक्थभागिन् *m.*, उत्तराधिकारिन् *m.* **-Legator,** *s.* उत्तरदानकारिन् *m.*

Legend, *s.* कथा, उपाख्यानं, आख्यायिका, पुरावृत्त-पुराण-कथा, पुरावृत्तं, लोक-जन-कथा, इतिहासः, पुराणं. **-ary,** *a.* पौराणिक (की *f.*), पुराणोक्त, पुराणकथित. **-s.** ऐतिहासिकः, पुराणकथकः.

Leger-de-main, *s.* हस्तलाघवं-चापल्यं माया, कुहका-कं, इंद्रजालं.

Legible, *a.* व्यक्ताक्षर, सुवाच्य, निर्वाच्य, सुव्यक्त सुस्पष्ट, स्पष्टाक्षर. **-Legibly,** *adv.* सुस्पष्टं, व्यक्ताक्षरैः, सुव्यक्तं.

Legion, *s.* चमूः, सेना, वाहिनी; *See* **Force. 2** सैन्य-दलं-गुल्मः-व्यूहः-समूहः. **3** चक्रं, निवहः; 'their name is a l.' अतिसंख्याः-संख्यातीताः-ते.

Legislate, *v. i.* व्यवस्थां वि-धा 3 U or कृ 8 U; विधीन् रच् 10 or प्रक्लृप् c. or स्था c. (स्थापयति), व्यवस्था c. **-ion,** *s.* विधिप्रकल्पनं, व्यवस्था-नियम-विधानं, विधि-नियम-व्यवस्था. **-ive,** *a.* व्यवस्थापक, विधिकारिन्. **-or,** *s.* व्यवस्थापकः, शासितृ *m.*, शास्तृ *m.*, न्यायप्रवर्तकः, व्यवस्थाकारः. **-ure,** *s.* व्यवस्था-विधि-विधायिनी सभा.

Legitimate, *a.* न्याय्य, धर्म्य, उचित, यथायोग्य, यथान्याय; *See* **Lawful, Legal. 2** सत्य, यथार्थ. **3** धर्मज, औरस (सी *f.*), औरस्य, उरस्य, धर्मपत्नीज, स्वजात, सुजन्मन्; 'a l. wife' धर्मपत्नी; 'a l. son' उरस्यः, औरसः-स्यः. -*v. t.* औरसीकृ 8 U. **-ly,** *adv.* यथान्यायं, धर्मेण, न्यायतः, धर्मानुसारेण, यथाधर्मं, युक्तं, यथोचितं, यथार्थं. **-Legitimacy,** *s.* न्याय्यता, धर्म्यता, यथार्थता, युक्तता, औचित्यं. **2** औरसत्वं, सुजन्मन् *n.*, धर्मजत्वं, औरसजन्मन् *n.*

Legume, Legumen, *s.* शमी, शिंबा, मुद्गः, शिंबिका. **2** शमीधान्य.

Leisure, *s.* अवसरः, अवकाशः, विश्रामः, क्षणः, कार्य-निवृत्ति *f.* -विच्छेदः, विश्रांति *f.*, 'being at l.' लब्धावकाश, प्राप्तावकाश, प्राप्तावसर, निर्व्यापार, लब्धक्षण, कार्यरहित. **-ly,** *a.* मंथर, मंद, अशीघ्र, अक्षिप्र, अत्वरित, सावकाश. -*adv.* 'at leisure,' मंदं मंदं, शनैः, अशीघ्रं, अक्षिप्रं, यथावकाशं, प्राप्तावसरं.

Lemon, *s.* जंबी(बि)रः, जभः, जंभीरः, जंभरः-लः, दंतशठः, फलपूरः, बीजपूरः; रुचकः, मातुलुंगकः; (fruit) जंबीरं, जंभफलं &c.

Lemonade, *s.* जंबीररसः.

Lemures, *s.* *See* **Devil.**

Lend, *v. t.* (आविहितकालात्) दा 3 U, 1 P, सम्-ऋ c. (अर्पयति) निक्षिप् 6 P, न्यस् 4 U; 'l. money' ऋणं दा 'l. money at

interest' कुसीदं कृ 8 U; 'l. one's hand to' उपकृ, अनुग्रह् 9 P; *See* **Help;** 'l. one's ear to' श्रु 5 P, सावधानो भूत्वा आकर्ण् 10. **-er,** *s.* उत्तमर्णः, ऋणदायिन् *m.*, ऋणदः. **-ing,** *s.* ऋणदानं, ऋणसमर्पणं.

Length,-en, *See* under **Long.**

Lenient, *a.* सौम्य, मृदु, अतीक्ष्ण, कोमल, अतीव्र, अपरुष; क्षमावत्, क्षमिन्, सदय. कृपालु, दयार्द्र. 2 सान्त्वकारिन्, साम in comp.; 'a l. measure' सामोपायः, सामोपचारः, सामप्रयोगः. **-ly,** *adv.* अनुग्रं, अतीक्ष्णं, सौम्यं, सदयं, अपरुषं, क्षमापूर्वं. **-Lenity, -Leniency,** *s.* सौम्यता, मृदुता, अतीक्ष्णता, अतीव्रता, कोमलता, क्षमा, क्षमाशीलता, दया, दयार्द्रभावः, कृपा; सामन् *n.*, सामबुद्धि *f.* **-Lenitive,** *a.* शमक, शांतिद, शांतिकर (री *f.*). 2 स्निग्ध, चिक्कण **-s** प्र-उप-शमनं, क्लेशापहं, शूलघ्नं

Lens, *s.* काचः; 'convex l.' मध्योन्नतकाचः; 'concave l.' मध्यनिम्नकाचः; 'a double convex l.' यवः; 'a crystal l.' सूर्यकांतः, अर्काश्मन् *m.*, दीप्तोपलः.

Lenticular, *a.* मसूरोपम.

Lentiform, *a.* यवाकृति, यवरूप

Lentigo, *s.* जडुलः, कालकः, पिप्लुः

-Lentiginous, *a.* जडुलिन्, कालकयुक्त

Lentil, *s.* मसूरः, मसूरा.

Lentous, *a.* सांद्र, श्यान, घन. **-Lentor,** *s.* सांद्रता, श्यानता.

Leo, *s.* सिंहः, सिंहराशिः. **-Leonine,** *a.* सैंह (ही *f.*) सिंहशील-धर्मन्.

Leopard, *s.* चित्रकः, चित्रव्याघ्रः.

Leper, *s.* कुष्ठिन् *m.*, श्वित्रिन् *m.*, कुष्ठरोगिन् *m.*, कुष्ठपीडितः. **-Leprosy,** *s.* कुष्ठं, श्वित्रं, कोठः, मंडलकं, कुष्ठरोगः, श्वेतरोगः, ... *n.*, 'black l.' महारोगः, महाव्याधिः, ...कुष्ठं; 'wasting l.' गलत्कुष्ठं. **-Leprous,** *a.* कुष्ठिन्, श्वित्रिन्, कुष्ठपीडित

Lesion, *s.* अपकारः, पीडा, क्षति *f.*

Less, *a.* न्यून, ऊन, अल्पतर, अल्पीयस्, क्षुद्रतर, स्तोकतर, सूक्ष्मतर. **-adv.** न्यूनं, अल्पं. &c. 'no l. than' ex. by अवर-*a.*, 'अवराः साक्षिणः; 'much l.' किमुत, किं पुनः, किम्; 'a little l. than 10,000 years' किंचिदूनं शरदामयुतं (R. x. 1);); (as a suffix) ex. by अ, निर्, विहीन, रहित, वर्जित, हीन, विगत, *in comp.* **-en,** *v. t.* न्यूनीकृ 8 U, ऊन् 10, ह्रस् *c.*, अप-चि 5 U, लघूकृ, लघयति (D.), क्षि 1, 5 P or c. **-v. i.** ह्रस् 1 P, न्यूनीभू 1 P, अल्पीभू, क्षि-अपचि-*pass.* **-er,** *a.* क्षुद्रतर, &c.

Lessee, *s.* पट्टकिलकाधारिन् *m.*

Lesson, *s.* पाठः, अध्यायः. 2 शासनं, उपदेशः, बोध-धर्म, शिक्षा. 3 वाचनं, नर्तनं; take l. from' उपदेशं ग्रह् 9 U. **-v. t.** उपदिश् 6 P, शास् 2 P.

Lest, *conj.* नोचेत्, अन्यथा, 'love not sleep l. thou come to want' संप्रसक्तो मा भव नोचेत् अकिंचनो भविष्यसि; sometimes ex. by न इति or कदाचित् with pot. or मा with simple future or imperative; मा कस्यापि तपस्विनो हस्ते पतिष्यति (S. 2) 'l. she fall into the hands &c.' मा...विकारो वर्धतां (M. 4); 'l. he should kill us' मा नो हिंसीदिति; 'beware l. you be enticed by women' तथा प्रयतेथा यथा न प्रलोभ्यसे वनिताभिः (Ka. 109.)

Let, *v. t.* अनु-ज्ञा 9 U, अनुमन् 4 A, अनु-मुद् 1 A, सह् 1 A; oft. ex. by the imperative of aorist forms without अ; 'l. it not so happen' एवं मा भूत्. 2 भाटकेन दा 3 U; मूल्येन दा or विसृज् 6 P. 3 रुध् 7 U, निवार् 10, स्तंभ् 9 P. 4 (Blood) स्रु *c.*, मोक्ष् 10; *See* **Bleed;** 'l. alone' न उपद्रु 1 P, न बाध् 1 A, oft. by आस् 2 A, स्था 1 P; 'now l. it alone' आस्तां तावदेव; 'l. go,' 'l. loose' मुच् 6 P or c., मोक्ष्, शिथिलीकृ 8 U; शिथिलयति (D.), स्रंस् *c.*, विसृज्, अ(अं)व-स्रथ् 1 P, 10; 'l. ing his hand go' मुक्त-स्रस्त-शिथिलित-हस्तः; l. slip' मुच्, विक्षिप् 6 P, वृथा या *c.* (यापयति). **-down,** अवतॄ *c.*, अवरुह् *c.* (रोपयति), अव-नि-पत् *c.*, अवमुच्, अवसृज्, अधः नि-धा 3 U or स्था *c.* (स्थापयति). **-in,** प्रविश् *c.*; अभ्यंतरीकृ. **-off,** निर्-वि-मुच्, मोक्ष्, क्षिप्, ईर् *c.* विसृज्, मोक्ष; 'l. off with a fine' दंडदानेन विमुक्त. **-out,** मुच्, मोक्ष्. 2 भंज् 7 P, भिद् 7 P, प्रकाश् (as secrets). 3 पणेन दा.

Lethal, *a.* *See* **Deadly** under **Die**

Lethargy, *s.* जाड्यं, मंदता, निद्रालुता, आलस्यं, तंद्रा, तंद्रि-द्रा *f.*, जडबुद्धित्वं, निद्रालसता, कार्यजडता, कार्यद्वेषः, आलस्यं. 2 घोर-गाढ-निद्रा, निर्भरनिद्रा. **-ic,** *a.* निद्रालु, निद्रालस, निद्राशील, जड, मंद, जडबुद्धि, ...मति; कार्यजड, कार्यविमुख (खी *f.*); आलस्यशील. **-ically,** *adv.* जडवत्, मंदवत्. **-icalness,** *See* (*s.*)

Lethe, *s.* विस्मृति *f.*, विस्मरणं, स्मृतिनाश-लोपः. 2 वैतरणी.

Letter, *s.* अक्षरं, वर्णः; 'printing l.' मुद्राक्षरं 2 लेखः, पत्रं, लेख्यं, संदेशपत्रं; 'by l.' पत्र द्वारेण; 'l. from an inferior to a superior' विज्ञप्ति-विज्ञापना-पत्रं; 'l.-carrier' पत्रवाहः, लेखहारः. 3 शब्दार्थः, अक्षरार्थः, वाच्यार्थः, वचनं; 'obey orders to the l.' यथावचनं आज्ञामनुरुध् 4 A. 4 (Letters) विद्या, ज्ञानं; 'a man of l. s' कृतविद्यः विद्वान्, *See* **Learned;** 'l. by l.' अक्षरशः

'a dead l.' लुप्तार्थं वचनं. -*v. t.* अक्षरैः अंक् 10 or मुद्र् 10. **-ed,** *a.* अक्षरांकित, अक्षरमुद्रित-चिह्नित. **2** कृतविद्य, उपात्तविद्य; *See* **Learned.**

Lettuce, *s.* हरितकं, शिग्रुः.

Levant, *a.* पूर्वदेशज, प्राग्भव, पौरस्त्य, पूर्वदिक्स्थ. -*s.* पूर्वदेशः, प्राग्देशः.

Levee, *s.* राजदर्शनं, राजदर्शनमेला, दर्शकमेला.

Level, *a.* सम, समस्थ, सपाट, समरेख, समभूमिस्थित; 'lie l. with the ground' भूमसमीकृ pass. **2** क्षितिजसमसूत्र; 'a l. ground' समभूमि *f.*, सानु *m. n.*, प्रस्थः, समस्थलं-ली. -*s.* समं, समभूमिः- स्थलं, समतलं-पृष्ठं-देशः, प्रस्थः, प्रदेशसमता, पाटः. **2** समता, तुल्यता, साम्यं, तुल्य or सम-भावः or वृत्ति *f.*; 'reduced to the l. of the poor, दरिद्रसमतां नीत-गमित; 'on a l. with' सम, तुल्य, समान; 'along the l' अनुप्रस्थं. **3** लक्ष्यसूत्रं-देशः. **4** नियमः, सूत्रं. -*v. t.* समीकृ 8 U; समस्थलीकृ. **2** लक्ष्यीकृ, उद्दिश् 6 P सं-धा 3 U, प्रेर् c, मुच् 6 P, क्षिप् 6 P. **-ler,** समकारिन् *m.*, विशेषनाशकः, भेद-भावलोपकः. **-ness,** *s.* समता, साम्यं, समभूमिभावः.

Lever, *s.* उत्तोलनदंडः; तुलायंत्रं.

Leveret, *s.* शशशिशुः-शावकः.

Leviathan, *s.* तिमिः, तिमिंगिलः.

Levigate, *v. t.* चूर्ण् 10, क्षुद् 7 U, पिष् 7 P. **2** श्लक्ष्णीकृ 8 U, परिष्कृ.

Levitate, *v. t.* लघूकृ 8 U.

Levitical, *a.* याजकीय, पुरोहितसंबंधिन्.

Levity, *s.* लघुता, लाघवं, लघिमन् *m.*, गौरवहीनता. **2** चापल्यं, चांचल्यं, तरलता, लोलता, चापलं, लौल्यं.

Levy, *v. t.* (Forces) समा-हृ 1 P, शस्त्राणि ग्रह् c., युद्धे व्या-पृ c. or प्रवृत् c. **2** (A tax) ग्रह् 9 U, आदा 3 A, दा c. (दापयति); 'l. ed taxes from them' स ताभ्यो बलिमग्रहीत् (R. i. 18). -*s.* सैन्यसमाहारः. **2** दापनं, ग्रहणं **3** सैन्यसमूहः.

Lewd, *a.* कामुक, कामवश, सुरतार्थिन्, लंपट, भोगासक्त, कामासक्त; *See* **Lustful. 2** दुष्ट, दुराचार, दुर्वृत्त, दुरात्मन्, पापात्मन्. **ly,** *adv.* कामुकवत्, लांपट्येन. **-ness,** *s.* लांपट्यं, भोगासक्ति *f.*, रतार्थिता, व्यवायेच्छा. **2** दुष्टता, दुराचारता, दौरात्म्यं.

Lexicon, *s.* कोशः-षः; अभिधानं, शब्दसंग्रहः-कोशः, निघंटुः. **-Lexicographer,** *s.* कोशकारः. **-Lexicography,** *s.* कोशरचना.

Liable, *a.* योग्य, अधीन, अर्ह, वश in comp.; gen. ex. by अर्ह् 1 P, पात्रं, आलु or शील in comp., or by pot. pass. part.; 'l. to punishment' दंडनीय, दंडयोग्य, दंडार्ह; 'l. to be blamed' निंदापात्रं; 'l. to fall' पतयालु, पतनशील; 'man is l. to err' मनुष्याः स्खलनशीलाः-प्रमादाधीनाः; *See* **Apt,** also. **2** अनुयोगाधीन, प्रष्टव्य, आज्ञाधीन, अभियोज्य. **-ness,-Liability,** *s.* अधीनता, शीलता, पात्रता, आलुता in comp.; आज्ञानाधीनता, अनुयोगाधीनता. **2** (Liabilities) ऋणं, उद्धारः, पर्युदंचनं.

Liaison, *s.* संबंधः, प्रेमबंधः.

Liar, *s. See* under **Lie.**

Libation, *s.* उदक-दानं-तर्पणं-पातनं-निषेकः, (देवतार्थं) पेयनिषेकः **2** तर्पणोदक, निषिक्तद्रव्यं-रसः, अभिधारः; 'to make l. s to' उदकादिदानेन तृप् c., उदकं पत् c. or निषिच् 6 P.

Libel, *s.* परि(री)वादलेखः, अपवाद-निंदाआक्षारण-लेखः-पत्रं, पिशुनलेख. -*v. t.* परिवद् 1 U, अप-भाष् 1 A, अभि-शंस् 1 P, निंदापत्रेण कलंकयति (D.) or आक्षर् 10; 'not only he who actually l.s great persons, but he also who countenances such l is guilty' न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् (K. v. 83). **-ler,** *s.* अपवादकः, अभिशंसकः, परिवादरतः, अभ्यसूयकः, पिशुनः. **-lous,** *a.* परिवादगर्भ, कलंकावह, अपवादक, पिशुन, कलंक-दुष्कीर्तिकर (री *f*).

Liberal, *a.* उदार, वदान्य, दानशील, अकृपण, बहुप्रद, स्थूललक्ष्य, त्यागिन्, त्यागशील, मुक्तहस्त, उदारहस्त, व्यय-पर-शील. **2** (L.-minded) उदार-धी-चेतस्-चरित, महात्मन्, महानुभाव, महेच्छ, महाशय. **3** कुलीन, महाकुल, अभिजात. **4** विपुल, बहुल, प्रचुर, परिपूर्ण, अतिरिक्त; 'l. education' सार्वविषयिकं ज्ञानं. **-ity,** *s.* औदार्यं, वदान्यता, त्यागः, दानशीलता, अकार्पण्यं, बहुप्रदत्वं, दातृत्वं, अतिदानं. **2** माहात्म्यं, उदारचित्तत्वं, चित्तौदार्यं. **-ly,** *adv.* उदारतया, अकार्पण्येन, मुक्तहस्तेन, अति-व्ययेन-त्यागेन; बाहुल्येन, बहु :.

Liberate, *v. t.* मुच् 6 P or c., मोक्ष् 10, वि-निर्°; विसृज् 6 P, निस्तॄ c., उद्-धृ-हृ 1 P, त्रै 1 A. **-ion,** *s.* वि-,मुक्ति *f.*, मोचनं, मोक्षः-क्षणं, उद्धारः, त्राणं, निस्तारः. **-or,** *s.* वि-,मोचकः, मोक्षकः, उद्धर्तृ *m.*, तारकः, निस्तारकः, रक्षितृ *m.*

Libertine, *a.* खंडितवृत्त, व्यसनिन्, कामविषयासक्त, विषयिन्, भोग-काम-आसक्त, दुर्वृत्त, निर्-अ-मर्याद, भ्रष्टचरित्र, मुक्तमर्याद, दुराचार, व्यभिचारिन्, कामवृत्त. -*s.* लंपटः, कामुकः, कामासक्तः, विटः, स्त्री-लंपटः-परः-सेविन् *m.* **-ism,** *s.* व्यसनं, व्यभिचारः, लांपट्यं, विषयासक्ति *f.*, भोग-काम-आसक्तिः, दुर्वृत्तता, अमर्यादा, स्त्रीव्यसनं-व्यासंगः.

Liberty, *s.* स्वाधीनता, स्ववशता, स्वतंत्रता, स्वातंत्र्यं, अनायत्तता, अपारतंत्र्यं, अयंत्रणं, दास्याभावः, अदास्यं, स्वाच्छंद्यं, स्वेच्छाचारता. 2 स्वेच्छा, स्वकामः, स्वरुचि *f.*, यदृच्छा. 3 अनुज्ञा, अनुमति *f.* 4 मुक्ति *f.*, मोक्षः-क्षणं, मोचनं. 5 विरहः, अभावः, शून्यता. 6 अधिकारः, क्षमता, शक्ति *f.* 7 कर्मावशता, दैवानधीनता, अदैवपरता. 8 अमर्यादा, मर्यादातिक्रमः, अविनयः, विनयातिक्रमः, विनयोल्लंघनं; 'don't take l. with your teachers' गुरुषु अविनयं मा कार्षीः; 'your ladyship is at l. to do what befits the occasion' यदत्रावसरप्राप्तं तत्र प्रभवति भवती (Ka.158); बंधे मोक्षे च अधुना सा ते प्रभवति (Ka. 354) 'she is at l. to detain or set you free'; 'to set at l.' मुच् 6 P or c. मोक्ष् 10; *See* **Liberate;** 'at l. अयंत्रित, निरवग्रह; *See* **Free.**

Libidinous, *a. See* **Lustful.**

Libra, *s.* तुला, तुलाराशिः. **-Librate,** *v. t.* तुल् 10. **-ion,** *s.* तोलनं.

Library, *s.* पुस्तकसंग्रहः-समूहः, ग्रंथसमुदायः-संग्रहः. 2 पुस्तकालयः, ग्रंथालयः, ग्रंथशाला, पुस्तकशाला-अगारं. **-Librarian,** *s.* ग्रंथशालाध्यक्षः, पुस्तकालयाधिकृतः, ग्रंथाध्यक्षः.

License, *s.* अनुज्ञा, अनुमति *f.*, आज्ञा; 'written l.' अनुज्ञापत्रं-लेखः. 2 अनियंत्रणं, मर्यादातिक्रमः, व्यतिक्रमः, उत्क्रमः, निर्यंत्रणं; 'poets have l. (in every way)' निरंकुशाः कवयः. *-v. t.* अनु-ज्ञा 9 U. आज्ञापत्रं-अनुमतिलेखं-दा 3 U. अनुमन् 4 A. **-Licentiate,** *s.* लब्धानुज्ञः, अधिकारयुक्तः, दत्ताधिकारः.

Licentious, *a.* अनियंत्रित, निर्मर्याद, स्वेच्छाचारिन्, कामवृत्त, स्वैरिन्, उच्छृंखल, अवश्य, अनंकुश. 2 कामासक्त, उद्दामचरित, अतिक्रांतमर्याद, दुराचार, अशिष्टाचार, धर्मभ्रष्ट, व्यसनिन्, व्यसनासक्त, विषयासक्त, कामुक, दुर्वृत्त, लंपट; स्त्रीव्यसनिन्; *See* **Libertine, Lustful. -ly,** *adv.* उच्छृंखलं, निर्यंत्रणं, निर्मर्यादं; कामुकवत्, लंपटवत्. **-ness,** व्यभिचारः, अत्याचारः, दुराचारः, दुर्वृत्तता, व्यसनिता, भ्रष्टचारित्र्यं, लांपट्यं, स्त्रीव्यसनपरता, मर्यादातिक्रमः, व्यतिक्रमः, उत्क्रमः, निर्यंत्रणा.

Lichen, *s.* सुकरि, सुकराक्रांता शिलावल्कल.

Lick, *v. t.* लिह् 2 U, आ-अव-सं-परि°; 'l. up' ग्रस् 1 A, गृ 6 P. 2 तड् 10, प्र-हृ 1 P; 'l. the dust (before one)' भूमौ निपत् 1 P or शी 2 A. **-ing,** *s.* लेहः-हनं. 2 आघातः, प्रहारः, ताडनं, दंडाघातः, वेत्रप्रहारः. **-Lickerish,** *a.* सुरस, स्वादु, मिष्ट. 2 लंपटस्वभाव, भोगोत्सुक.

Licorice, *s.* यष्टिमधु *n.*, यष्टि(ष्टी)मधुकं, मधुयष्टिका, मधुकं, क्लीतकं.

Lid, *s.* पिधानं, आच्छादनं, आवरणं, पटलं, पुटः-टं-टी, छदः-दनं, शरावः, मुद्रः, वर्धमानकः, उदंचनं; 'eye-l.' नेत्रच्छदः, अक्षिपुटः.

Lie, *s.* असत्यं, अनृतं, वितथं, असत्यं, अलीकं, मृषा or अनृत-वाक्यं or वचनं, मृषोक्ति *f.*, मृषोद्यं, मिथ्या-वादः-भाषणं-वचनं-उक्तिः, मृषा-असत्य-वादः, असत्यभाषणं. *-v. i.* शी 2 A, अधि-शी (with acc.), आस् 2 A, निपत् 1 P, संविश् 6 P. 2 वस् 1 P, स्था 1 P, अव-स्था 1 A; gen. by भू, वृत् 1 A, अस् 2 P, विद् 4 A; 'Lanka l. s to the south of India' लंका भारतवर्षस्य दक्षिणतोऽवस्थिता or वर्तते. 3 **Consist in,** q. v. 'l. hard upon' पीड् 10, बाध् 1 A, आ-पत् c. **-down,** शी, संविश्, स्वप् 2 P, निपत्. **-in,** प्रसवावस्थायां वृत्; 'lying-in-chamber' अरिष्टं, सूतिकागृहं; 'l. in the wait' निभृतं स्था, नि-ली 4 A; 'l. in the way' रुध् 7 U, अंतर्-इ 2 P, अंतरायो भू. **-on,** आ-अव-समा-लंब् 1 A, आश्रि 1 U, *See* **Depend.** 2 'Be incumbent' q. v. **-with,** संगम् 1 A, अनुगम्, मैथुनं कृ 8 U. 2 अधीन-*a.* भू; गम्; 'the fault l. s with you entirely' सर्वथा तवैवायं दोषः, त्वमेवात्र सर्वात्मना दोषभाक्; 'the fault l. with my friend' सखीगामी (अयं) दोषः (S. 4).

Lie, *v. i.* अनृतं-मिथ्या-असत्यं-वद् 1 P or ब्रू 2 P or भाष् 1 A, &c. (Speak, q.v.), 'thou liest in the throat' नितांतमनृतं वदसि; **-Liar,** *s.* मिथ्या-मृषा-अनृत-असत्य-वादिन् or भाषिन्, असत्यवाच्, अलीक-वाच्, अनृतिन्, all *m.* असत्यशीलः, मिथ्यावादशीलः. **-Lying,** असत्य-अनृत-मिथ्या-भाषणं, मृषा-मिथ्या वादः, मिथ्यावादित्वं, असत्यता; *See* (*s.*). *-a.* मृषावादिन्, अनृतवाच्, असत्य; *See* above.

Lief, *adv.* कामं, प्र-नि-कामं, कामतः, इच्छापूर्वं, संतोषेण, प्रीत्या.

Liege, *s.* प्रभुः, स्वामिन् *m.*, ईश्वरः, पतिः; महाराजः, देवः (in addressing). *-a.* भक्त, सेवा-भक्ति-बद्ध, प्रभु-स्वामि-भक्त, स्वाम्यनुरक्त, प्रभुवश; 'l. man' भक्तः, प्रभुसेविन् *m.* 2 आज्ञापकः; better ex by (*s.*)

Lien, *s.* आविहितकाल *-a.* स्वाम्यं or अधिकारः or स्वत्वं.

Lientery, *s.* अतिसारः, आमातिसारः.

Lieu, *s.* स्थानं, भूमि *f.*; 'in l. of' स्थाने, विनिमयेन; *See* **Instead;** (of) **-Lieutenant,** *s.* प्रतिनिधिः, प्रतिपुरुषः, (lit.) सेनापतिप्रतिनिधिः; 'l. governor' प्रतिशासकः; 'lord l.' राजप्रतिनिधिः.

Life, *s.* जीवनं, जीवितं, प्राणधारणं, असुधारणं. 2 जीवः, सत्त्वं, जीवितं, चैतन्यं

जीवनम्, प्राणधारणं, प्राणधारणम् n., जीवातुम्; 'endowed with l.' जीविन्, प्राणिन्, सजीव, सचेतन; 'love of l.' जीवितवृष्णा, जिजीविषा; 'impatience of l.' जीवित-द्वेष-आशः; 'deprived of l.' हतप्राण-जीवित, गतप्राण; 'support of l.' प्राणयात्रा-धारणं-रक्षणं; 'reckless of l.' जीवितनिरपेक्ष, जीवितनिरपेक्ष; 'means of l.' जीवनोपायः. 3 (Life-time) आयुस् n., जीवितं, जीवनं, जीवितकालः, आयुर्मर्यादा, आयुःपरिमाणं; 'possessed of long l.' दीर्घायुस्, आयुष्मत्, चिरायुस्; 'for l.' 'during l.' 'all one's l.' यावज्जीवं, आमरणात्; 'in all one's l.' आजन्म, जन्मतः प्रभृति or आजन्म; 'my lamp of l. is nearly out' निर्वाणभूयिष्ठो मे जीवितप्रदीपः or अवसितप्रायो मे जीवितावधिः. 4 (fig.) जीवितं, प्राणाः, (त्वं जीवितं मे U. 3). 5 संसारः, भवः, संसृति f., लोकयात्रा, भूलोकवासः, इहवासः. 6 वृत्ति f., आचारः, व्यवहारः, रीति f., चेष्टितं, प्रवृत्तिः, वृत्तं, आचरणं; 'leading a virtuous l.' साधुवृत्त, सदाचार, पुण्यमार्ग. 7 चरितं, चरित्रं, जीवनवृत्तांतः, चरित्ररचना-कथनं. 8 अवस्था, दशा, स्थिति f., वृत्तिः, भावः, गति f. 9 उत्साहः, वीर्यं, तेजस् n., सत्त्वं, रसः; 'bring or restore to l.' उज्जीव् c., सोच्छ्वास-a. कृ 8 U, असून् प्राप् c., (परीक्षितं दुर्लभानसून्प्रापितवान् Ka. 175); 'come to l.' उज्जीव् 1 P; 'active l.' प्रवृत्तिः, प्रवृत्ति-संसार-मार्गः, लोकव्यवहारः; 'retired l.' निवृत्तिः, निवृत्तिमार्गः; 'he entered on a military l.' योधवृत्तिमाश्रयत; 'engaging in public l.' लोकव्यवहारप्रवृत्तिः; 'in this l.' इह, इहलोके; 'the vicissitudes of l.' संसारचक्र-परिवर्तनं, दशांतराणि; 'l.-blood' प्राणः, तत्त्वं, सारभूतं द्रव्यं; 'l.-giving' प्राणद, जीव-द-दायिन्; वीर्यद, उत्साहकर (री f.); 'l. guard' राजपरिचरः, शरीररक्षकः; 'l.-time' जीवितावधिः, जीवितकालः; 'during one's l.-time' यावज्जीवं. -less, a. गतजीवित, गतासु, परासु, व्यसु, गत-नष्ट-प्राण, हतजीवित, प्राण or जीव-रहित or हीन, अचेष्ट. 2 अजीव, निर्जीव, वि-अ-चेतन, चैतन्य-हीन-रहित, निश्चेतन. 3 निःसत्त्व, निरुत्साह, निस्तेजस्, सत्त्व-रस-हीन.

Lift, v. t. उन्नम् c. (नमयति), उद्गम् c. (गमयति) उच्छ्रि 1 U. उद्यम् 1 A, उत्था c. (उत्थापयति), उत्क्षिप् 6 P, उद्वह् 1 P, उन्नी 1 P, उत्कृष् 1 P, उत्तुल् 10; oft. by उत् in comp.; 'with the neck l.-ed up' उत्कंधरः; उद्बाहुः, उद्ग्रीवः, उन्मुखः, &c. 2 (In rank) उत्कृष्टपदे नियुज् 7 A, 10, मानं संवृध् c., प्रतिपत्ति-पदवीं-उत्कर्ष-पदवृद्धिं-लभ् c. (लंभयति); 'l. with pride' दृप् c., गर्वेण उद्धन् 2 P, दर्पेण आ-ध्मा 1 P; 'to l. up the voice' तारस्वरेण-उच्चैः-आक्रुश् 1 P. —s. उन्नमनं, उन्नयनं, उत्क्षेपः, उत्थापनं. 2 प्रतिपत्ति f., पदवृद्धि f., उन्नति f. 3 उपकारः, साहाय्यं.

Ligament, s. बंधः, बंधनं, पाशः, स्नायुः शृंखला-लं-लः. 2 संधिबंधः, संधि-अस्थि-बंधनं

Ligature, Ligation, s. बंधनं, वेष्टनं, परि-आ-वेष्टनं, रज्जु f.

Light, a. लघु (in all senses), अगुरु, अल्पभार, अल्पप्रमाण, लघुभार, लघुप्रमाण; सुवाह्य, सुखवाह्य, सुवह, अदुर्वह, अदुःवह. 2 सुकर, सुखर, अकष्ट, सुसाध्य, सुगम, निरायास, अविषम, अकठिन. 3 चपल, लघु, लघुशरीर-गति. 4 सोल्लास, प्रफुल्ल, निश्चिंत. 5 चपल, चंचल, लोल, तरल, अस्थिर, अनवस्थित, लघुचित्त-स्वभाव-चेतस्, गांभीर्यहीन, निर्गौरव. 6 तुच्छ, क्षुद्र, अल्पक, तृणप्राय, लघ्वर्थ, अल्पार्थ, अल्प-लघु-प्रभाव; 'l. armed' लघ्वायुध, लघुशस्त्रभृत्; 'l.-fingered' लघुहस्त, चपलपाणि; 'l.-footed' लघु-शीघ्र-गति, द्रुतगति; 'l.-headed' लघुचित्त-चेतस्, चपल-लोल-मति; भ्रांत or विक्षिप्त-बुद्धि or चित्त; बुद्धिप्रमाद प्रलापिन्; 'l.-headedness' चित्त or बुद्धि-भ्रमः or विप्लवः; 'l-hearted' लघुचित्त-चेतस्, क्षुद्रमनस्; हृष्ट-प्रसन्न- हृदय, उल्लासिन्, प्रफुल्लचित्त, आनंदित, सोल्लास; 'l.-minded' लघु-चेतस्-चित्त, क्षुद्र or कृपण-बुद्धि or मति; 'l. spirited' हृष्टहृदय-चित्त, &c. 7 पांडु, श्वेत; oft. ex. by आ, ईषत्; 'l. red' श्वेतारुण, ईषद्रक्त; 'l. blue' श्वेतनील, आनील; 'l. food' सुपचं-सुपाकं-अन्नं; 'to make l. of' लघूकृ 8 U, लघु मन् 4 A, न गण् 10, तृणाय मन्. —v. i. आ-पत् 1 P; (अकस्मात्) आसद् c., प्राप् 5 P, आ-उपा-गम् 1 P. 2 अवतॄ 1 P, अव-रुह् 1 P, अव-नि-पत्; अध्यास् 2 A, अधि-शी 2 A (with acc.), निषद् 1 P, नि-ली 4 A. -en, v. t. लघूकृ, लघयति (D.); श्रम् c. (श्रमयति), प्र-उप°. -er, a. लघुतर, लघीयस् —s. तरालुः, वहित्रं, उडुपं. -ly, adv. लघु, लाघवेन, अल्पप्रमाणेन. 2 सुखेन, अकष्टेन, अनायासेन. 3 निष्कारणं, हेतुं विना. 4 लघुबुद्ध्या, चपलं, सत्वरं. 5 लघुचेतसा, चंचलवत्, अस्थिरतया; 'to think l.' लघु मन् 4 A. -ness, s. (lit.) लघुता-त्व, लाघवं, अल्पभारत्वं, भाराभावः. 2 सुखं, सौकर्यं, अनायासः, सुसाध्यता, अकष्टत्वं. 3 सुवाह्यता, सुवहता. 4 लाघवं, चापल्यं, द्रुतगतित्वं, शरीरलघुता. 5 चापल्यं, चांचल्यं, अस्थिरता, लोलता, चपलता, अगौरवं, लघिमन्, लाघवं, लघुता. 6 तुच्छता, तुच्छत्व, क्षुद्रता. -some, a. हृष्ट, सोल्लास, प्रफुल्ल, आनंदित, सानंद.

Light, *s.* प्रकाशः, आलोकः, भा, प्रभा, आभा, द्युति *f.*, कांति *f.*, दीप्ति *f.*, तेजस् *n.*, ज्योतिस् *n.*, रुचि *f.*, भास् *f.*, त्विष् *f.*; वर्चस् *n.* 2 प्र-,दीपः, दीपिका; 'l. house' दीपगृहं. 3 ज्ञानं, बोधः, अवगमः, प्रकाशः. 4 प्रसिद्धि *f.*, प्रख्याति *f.*, प्रकाशत्वं, प्रकाशता, प्रकटता. 5 दृष्टि *f.*; 'See or come to l.' प्रसिद्धि-प्रकाशतां-गम् 1 P, प्रकाशी भू 1 P, आविर्भू, प्रादुर्भू; 'bring to l.' प्रकाश् c., प्रकटीकृ 8 U, व्यक्तीकृ, आविष्कृ, वि-वृ 5 U, प्रकाश c. (प्रकाशयति); 'to throw l. on', विशदीकृ, विवृ, प्रकाश् c.; *See* **Explain**; 'from the l. of utility' उपयोगदृष्ट्या; 'considered in this l.' अनया दृष्ट्या. —*v. t.* दीप् c., उत्-प्र-सं°; प्र-,द्युत् c., प्रकाश् c., अव-वि-भास् c., ज्वल् c, प्र-उत्-सं°; सं-,इंध् 7 A; संधुक्ष् 10; तप् c., प्र-सं-उत्°; 'to be l.-ed' दीप् 4 A, ज्वल् 1 P. **-en,** —*v. t.* प्रकाश् c., दीप् c., ज्वल् c., द्युत् c.; *See* (*v. t.*) above —*v. i.* स्फुर् 6 P, द्युत् 1 A, प्रकाश् 1 A, विलस् 1 P. **-er,** *s.* प्रकाशकः, द्योतकः, दीपकः, द्युतिदः. **-less,** *a.* निष्प्रभ, अप्रभ, निरालोक, निस्तेजस्. **-some,** *a.* दीप्तिमत्, प्रकाशवत्, सुप्रभ, तेजस्विन्, सुप्रकाश, तेजोमय (यी *f.*). **-ning,** *s.* तडित्, विद्युत्, सौदामि(म)नी, अचिरप्रभा, क्षणदा, चंचला, चपला, शतह्रदा, ह्रादिनी, झंपा, ऐरावती, क्षण-प्रभा-द्युति (all *f.*); 'fire of l.' वैद्युतः अग्निः; 'forked l.' तडिल्लता, विद्युल्लता; 'the falling of l.' विद्युत्पातः; 'struck by l.' विद्युता उपहत.

Ligneous, *a.* काष्ठ-दारु-मय (यी *f.*), काष्ठ-दारु-रूप.

Ligniferous, *a.* काष्ठद, दारुप्रद.

Ligniform, *a.* काष्ठरूप, काष्ठाकृति.

Like, *a.* सदृश (शी *f.*), तुल्य, सम; समान, सन्निभ, अनुकारिन् (with gen. or instr.); oft. by उपम, निभ, रूप, विध, प्रतिम, संकाश, नीकाश, प्रतिकाश, भूत, (all in comp.); also by स or अनु in comp.; 'of l. properties' सगुण, अनुगुण-धर्मन्, सम-तुल्य-गुण, समभाव; 'of l. form' सरूप, अनुरूप, तुल्याकृति, तुल्यरूप; 'l. a father' पितृभूतः, पितृस्थानीयः; 'of l. class' सजाति, सजातीय, सवर्ण, सकर्म, तुल्यवर्ण; 'almost l. Hara' हरकल्प; 'l. this' ईदृश-क्ष्, एतादृश-क्ष्; 'l. that' तादृश्-श; 'l. what' कीदृश्-श; l. which' यादृश्-श; 'l. me, us' मादृश, अस्मादृश, &c., 'l. thee, you' त्वादृश, युष्मादृश, &c.; 'l. your honour' भवादृश; 'to be l.' अनुकृ 8 U (with gen.), संवद् 1 P (with instr.), अनुहृ 1 P (with acc.); *See* **Resemble**; **the son was l. his generating cause** (**father**)' न कारणात् स्वाद्बिभिदे कुमारः (R. v. 57); '**thee and the l.**' एवमादि; '**in l. manner**' तथा, एवं, तद्वत्, तथैव, एवमेव, एवंविधं. —*s.* समः, तुल्यः, सदृशः, तुल्यगुणः, समकक्षः; '**his l. was and will never be seen**' अनेन सदृशो न भूतो न भविष्यति. —*adv.* Ex. by वत् in comp., इव, यथा, निर्विशेषं in comp.; 'l. an earthen pot' मृद्घटवत्; often by Karm. or Bah. comp.; '**black l. a cloud**' मेघश्याम; 'having a moon-l. face' चंद्रमुख; 'brought up l. one's own children' अपत्यनिर्विशेषं संवर्धित; 'to act l.' अनुकृ. **2 Likely,** q. v. —*v. t.* रुच् 1 A (with dat. of person who likes); अभिनंद् 1 P, अनु-सं-अभि-मन् 4 A, अनुरुध् 1 A, प्रशंस् 1 P, प्री pass., तुष् 4 P; 'does not l. the present' उपायनं नाभिनंदति, उपायनेन न तुष्यति &c., स्निह् 4 P, अनुरंज् pass. (with loc.). —*v. i.* इष् 6 P, अभिलष् 1, 4 P, रुच्; oft. by काम in comp.; 'just as you l.' यत्ते छंदः (V. 3), यद्रुचये रोचते; 'doing as one l.-s' : कामचारः, स्वैरवृत्तः, स्वच्छंदः, स्वैरिन्; 'taking what form he l.-s' कामरूपः; 'do what you l.' यथाभिलषितं क्रियतां. **-ed,** *a.* मत, अभि-अनु-सं-° इष्ट, प्रिय, दयित. **-en,** *v. t.* उप-मा 3 A, 2 P, सदृशीकृ; *See* **Compare.** **-ing,** *s.* रुचि *f.*, अभिरुचिः, कामः, इच्छा, लोभः, प्रीति *f.*, तुष्टि *f.*, प्रणयः, अनुरागः, अभिलाषः, छंदः, छंदस् *n.*, सं-अनु-मति *f.*: 'he was not to her l.' स न तस्या रुचये बभूव (R. vi. 44); 'of your l.' त्वदभिमत. **-ness,** *s.* सादृश्यं, साम्यं, तुल्यत्वं, आनुरूप्यं, सारूप्यं, तुला, उपमा, अनुकारः. संवादः, आनुगुण्यं, औपम्यं, &c. **2** वर्णः, आकृति *f.*, आकारः, मूर्ति *f.* **3** प्रतिमा-यातनं, प्रतिरूपं-कृतिः, प्रतिमूर्तिः, प्रतिच्छंदः, चित्रं, आलेख्यं, प्रतिबिंबं; 'a speaking l.' संभाषिणी आकृतिः. **-wise,** *adv.* तथैव, तथा, तद्वत्. **2** अपि, अपि च, किं च, तथा, अपरं च. **-Likely,** *a.* संभाव्य, संभवनीय, उपपन्न सत्यसंकाश; श्रद्धेय; 'it is l. that' इति संभवति or उपपद्यते. **2** (Probable) ex. by प्रायः, प्रायशः, प्रायेण, with pot. pass. part., or by अपि नाम; 'he is l. to come to-morrow' प्रायः श्वः स आगंतव्यः; अपि नाम तयोः अविघ्नः पाणिग्रहः स्यात् (Mal. 1) 'is it l. that &c.' **-hood, -ness,** *s.* संभाव्यता संभवः; better by (*a.*); *See* **above.**

Lily, *s.* नलिनी, उत्पलं, कुमुदं, पद्मं; *See* **Lotus.**

Limation, *s.* मार्जनं, लोहमार्जनेन घर्षणं.

Limature, *s.* लोहचूर्णं, लोहकणं.

Limb, *s.* अंगं, अवयवः, (lit. & fig.); गात्रं; 'over every l.' प्रत्यंगं, सर्वांगीण-*a.*; 'l. by l.' अवयवशः, गात्रे गात्रे. 2 प्रांतः, कोटि *f.*, सीमा. **-ed,** *a.* अंगिन्, सावयव; 'large-l.' बृहदवयव, महांग (गी *f.*); 'slender-l.' तन्वंग. कोमल-पेलव-अंग **-less,** *a.* अनंग, निरवयव,अंगहीन

Limber, *a.* मृदु, कोमल, शिथिल, अदृढ, नम्य.

Limbo, *s.* नरकः, निरयः. 2 कारा, कारागारं, बंधनागारं.

Lime, *s.* (Tree) जंबीरः; *See* **Lemon. 2** (Quick-l) चूर्णः-र्णं, कर्करः; 'l.-water' सुधा, लेपः (for colouring); 'l.-stone' चूर्णखंडः, चूर्णोपल, कर्करं. **-y,** *a.* चूर्णमय (यी *f.*), सचूर्ण, कर्करमय. 2 श्यान, सांद्र, चूर्णोपम.

Limit, *s.* अवधिः, मर्यादा, सीमा, सीमन् *f.*, पर्यंतः, अंतः, प्रांतः, परिच्छेदः; परिमाणं, इयत्ता, अवसानं; वेला (of sea); 'of narrow l. (scope)' अल्पविषय-*a.*; 'set or fix a l. to' परिच्छिद् 7 P; 'no (definite) l. can be set to his fame' तस्य यश इयत्तया परिच्छेत्तुं नालं (R. vi. 77). **-v. t.** परिच्छिद्, परि-मा 2 P, 3 A; इयत्तया परिच्छिद्, सीमां नि-रूप् 10 or निर्धृ 10; *See* **Define. 2** सं-नि-यम् 1 P or c.; सं-हृ 1 P, संकुच् 1 P or c., नियंत्र् 10, निबंध् 9 P, निग्रह् 9 P. **-ation,** *s.* परिच्छेदः, सीमा-मर्यादा-निरूपणं. 2 परिमितता, सावधिकता, समर्यादत्वं, ससीमता. **-ed,** *a.* परिच्छिन्न, परिमित, मित, समर्याद, सावधिक; नियत, संहृत, अल्पविषय, संकुचित, अव्यापक, संबाध; 'not through the l. nature of (your) merits' न गुणानामियत्तया (R. x. 32); 'l. meaning' नियतार्थः; 'l. knowledge' अल्पविषयं ज्ञानं; 'l. monarchy' नियंत्रितं or संयतं प्रभुत्वं. **-er,** *s.* परिच्छेदकः, **-less,** *a.* अमित, अनंत, असीम, निरवधि.

Limmer, *s.* नीचजनः, अपसदः in comp.

Limn, *v. t.* लिख् 6 P or चित्र् 10. **-er,** *s.* चित्रकरः.

Limous, *a.* सकर्दम, पंकिल.

Limp, *v. i.* खंज् 1 P, लंग् 1 P. खोड्-खोड्-खोल्-1 P. **-s** लंगः, लंगगति *f.* **-a.** मृदु, शिथिल, कोमल. **-er,** *s.* खंजः, लंग-खंजगतिः. **-ing,** *a.* खंज, खोर, खोल, खोड, लंगगति, विकलगति. **-ingly,** *adv.* खंजवत्, लंगगत्या.

Limpid, *a.* स्वच्छ, प्रसन्न, विमल, स्वच्छतोय, प्रसन्नवारि, विमलजल. **-ness,** *s.* स्वच्छता, विमलता, प्रसादः.

Lin, *s.* पल्वलं, तडागः-गं, जलाशयः.

Linch-pin, *s.* अक्षाग्रकीलः, अ(आ)णिः, उद्धुषः.

Lincture, *s.* अवलेहः, लेह्यं.

Line, *s.* रे(ले)खा, रेखा. 2 पंक्तिः, पद्धतिः, सरणिः-णी, राजिः-जी, आवलिः-ली, ततिः, श्रेणिः-णी (all *f.*), माला. 3 सूत्रं, रज्जु *f.*, गुणः, तंतुः. 4 आकारः, आकृति *f*, वर्ण. 5 प्राकारः, वप्रः, परिखा, प्राचीरं. 6 (Of troops) वृंदः, व्यूहः, पंक्तिः, बलविन्यासः. 7 क्रमः, अनुक्रमः, पर्यायः. 8 परिपाटि-टी *f.*, श्रेणिः-णी, पंक्तिः, परंपरा, माला, पारंपर्यं, आवलिः-ली; आनुपूर्व्यं. 9 (Of conduct) मार्गः, पथिन् *m.*, रीति *f.*, सरणिः, व्यवहारः. 10 वंशः, विषयः, अंगं. 11 दिश् *f.*, दिशा, मार्गः. 12 भूचक्रं; *See* **Equator;** 'ruled l.' रेखा, अंकः; 'in a l.' पंक्तिक्रमेण, पंक्तिशः; 'by l. and rule' यथासूत्रं; 'l. of the face' वदन-मुख-रेखा; 'printed l.' पंक्तिः; 'l. of a stanza' पादः, चरणः-णं; 'in a regular l.' अनुक्रमेण, क्रमशः, आनुपूर्व्येण, अनुपूर्वशः; 'l. of the family' वंशक्रमः-परंपरा-आवलिः; 'a good l. of conduct' सुमार्गः, सुपथः; 'a bad l. of conduct' वि-कु-पथः, विमार्गः, उन्मार्गः; 'l. of study' अध्ययनक्रमः; 'l. of posterity' वंशावली; 'fishing-l.' बडिशसूत्रं; 'to draw l. s.' लिख् 6 P; 'draw l. s on the ground' भूमिं रेखाभिः वि-उत्-लिख् or अंक् 10: 'to draw the l.' वि-विच् 3, 7 U, भेदं दृश् c., or निरूप् 10. **-v. t.** अंतः आ-,छद् 10, अभ्यंतरे छद्. 2 पंक्तिक्रमेण स्था c. (स्थापयति) or निविश् c. 3 रेखाभिः अंक्; 'the streets were l. ed with guards' अनुरथ्यं पंक्तिक्रमेण रक्षिणः स्थापिताः. **-age,** *s.* अन्वयः, वंशः, कुलं, संतति *f.*, संतानः, गोत्रं, वंशावली, वंशपरंपरा; 'of royal l.' राजवंश्य, राजकुलप्रसूत; 'of high or noble l.' अभिजात, महाकुल. **-al,** *a.* रेखारूप-मय (यी *f.*). 2 परंपरागत, परंपरायात-प्राप्त, क्रमप्राप्त-आगत-आयात, अन्वयागत, परंपरीण, कुलक्रमागत; 'l. descent' अन्वयागमः, क्रमागमः, कुलक्रमागमः; 'l. descendant' संतानः, संततिः, अपत्यं. **-ally,** *adv.* परंपरया, पारंपर्येण, वंशक्रमेण, कुलक्रमागमेन, 'l. descended' वंशक्रमायात; *See* above. **-ing,** *s.* अंतराच्छादनं, अंतःपटलं-पुटं-वेष्टनं, आस्तरः-रणं. **-Lineament,** *s.* रेखा, वदन-मुख-रेखा, वदनाकारः, वदनाकृति *f.*, लक्षणं, चिह्नं. **-Linear,** *a.* पंक्ति or रेखा-रूप or मय (यी *f.*).

Linen, *s.* क्षौमं, क्षौमपटः-वस्त्रं; शाणपटः-वस्त्रं; **-a.** क्षौम-औम-(मी *f.*), शाण (णी *f.*), अतसीनिर्मित; 'l.-draper' क्षौमवस्त्रविक्रयिन् *m.*, वस्त्रविक्रयोपजीविन् *m.*

Linger, *v. i.* वि-लंब् 1 A, मंदायते (D.), चिर (रा)यति (D.), कालं क्षिप् 6 P os

ह्व 1 P, मंदं मंदं चल् (च्) 1 P. 2 विलम्ब् 1 A, विचाल् c. 3 चिरं-दीर्घकालं-स्था 1 P, or वृत् 1 A; 'l. ing on a sick bed' चिररोगिन्. -er, s. विलंबकारिन्, विलंबिन्, मंदगामिन्, मंदगति, चिरक्रियः, दीर्घसूत्रिन्, all m. -ing, a. दीर्घ, चिरस्थायिन्, चिर-दीर्घ-कालीन, चिरकालस्थ. 2 विलंबिन्, विलंबित, मंदगमन. -s. विलंबः, कालक्षेपः-यापनं. -ingly, adv. मंदं मंदं, विलंबेन, सविलंबं, मंदगत्या, कालक्षेपेण.

Linget, s. धातु-लोह-पिंडः.

Lingual, a. मूर्धन्य, मूर्धस्थानीय.

Linguiform, a. जिह्वाकृति, जिह्वारूप.

Linguist, s. भाषाकोविदः, शाब्दिकः, शब्दव्युत्पन्नः, भाषाप्रवीणः, भाषाज्ञः, बहुभाषाज्ञः, अनेकभाषानिपुणः. -ic, a. (s.) in comp.

Liniment, s. प्र-आ-वि-लेपः-पनं, उपदेहः, अभ्यंजनं, मर्दनौषधं.

Link, s. संधिः, ग्रंथिः. 2 बंधनं, बंधपाशः, शृंखला-लः-लं. 3 संयोगः, संबंधः, अन्वयः, संदर्भः, प्रबंधः. 4 उल्का, उल्मुकं 'l. s of life' जीवितनिबंधनानि; 'l. boy' उल्काभृत्. -v. t. संयुज् 7 U, 10, सं-धा 3 U, संश्लिष् c., संबंध् 9 P, ग्रथि-बंध् 1 P, संग्रथ् 9 P. See Knit. -ed, a. संयुक्त, संश्लिष्ट, संबद्ध, अन्वित, सान्वय.

Linn, s. जलप्रपातः, निर्झरः.

Linseed, s. अतसी, उमा, क्षुमा, उमा-अतसीबीजं, &c.

Linsey-woolsey, a. क्षौमौर्ण. 2 असार, निःसत्व; क्षुद्र.

Linstock, s. ज्वलनकाष्ठं, अग्निदशलाका.

Lint, s. क्षौमबंधः, विकेशिका.

Lintel, s. द्वाराग्रकाष्ठं, द्वारोर्ध्वदारु n.

Lion, s. सिंहः, हरिः, केसरिन् m., पंचास्यः पंचाननः, हर्यक्षः, कंठीरवः, मृगरिपुः,मृगाशनः पुंडरीकः, पंचनखः, चित्रकायः, मृगद्विट्; and comp. of इंद्रः, राजन्, पतिः, अधिपः, अधिपतिः with मृग or पशु; मृगपतिः, मृगराजः, मृगाधिपः, पशुपतिः, &c.; 'l.'s part' भूयिष्ठभागः. -ess, सिंही. -like,-ly, a. सिंहस्वभाव, सैंह (ही f.).

Lip, s. ओष्ठः (strictly upper), दशन-रदन-छदः, रद-दंत-छदः, दशन-दंत-वासस् n., अधरः (strictly lower); 'a red or cherry l.' बिंबो(बौ)ष्ठः, बिंबाधरः; 'a woman having cherry l.s' बिंबौष्ठी; 'drinking the l.' अधरपानं, अधरामृतसेवनं; 'l.-honeyed' मुखमधु; 'l.-loyalty' मुखभक्ति f., वाग्दर्शिता भक्तिः. 2 कर्णः, पार्श्वः,कंठः, मुखं, &c. -ped, a. ओष्ठ in comp.

Lipothymy, s. See Fainting, Swoon.

Lippitude, s. क्लिन्नाक्षता, चुल्लत्वं.

Liquate, See Liquefy below.

Liquefy, v. i. वि-,द्रु 1 P, वि-,ली 9 P, 4 A, जलसाद्भू 1 P, क्षर् 1 P, द्रवीभू. -v. t. वि-,द्रु c., वि-,ली c., द्रवीकृ 8 U,जलसात्कृ. -action, s. द्रवीकरणं, द्रावः, विलयः-यनं, क्षरणं, द्रवीभवनं. 2 द्रवत्वं, विलीनता.

Liquid, s. द्रवः, रसः, जलं, द्रव-वस्तु-द्रव्यं, पदार्थः. -a. द्रव, द्रुत द्रवरूप, विलीन, प्रवाहिन्, सरलं; 'reduced to a l. state' द्रवतामापन्न, विलीन, जलीभूत, रसतामुपेत (Ka. 122). -ity ..., s. द्रवत्वं रसता, द्रवभावः, ...धमः.

Liquidate, v. t. शुध् c., अपाकृ 8 U, निस्तॄ c., अपनी 1 P, अपवृज् 10; मुच् 6 P or c., मोक्ष् 10; 'debt contracted to l. another debt' ऋणार्णं. -ion, s. शोधनं, शुद्धि f., अपाकरणं, निस्तारः, मुक्ति f., मोक्षः-क्षणं, अपनयनं.

Liquor, s. सुरा, मद्यं, हाला, वारुणी, वरुणात्मजा, मदिरा, आसवः, शीधु (सीधु) m. n., हलिप्रिया, परिस्रुत f.,गंधोत्तमा, प्रसन्ना, इरा, कादंबरी, परिस्रुता; कश्यं; 'l.-shop' शुंडापानं; ,मदस्थानं, शुंडा, पानं; 'round of drinking l.' मधुवारः-क्रमः; 'distilling of l.' संधानं, अभिषवः; 'l.-ferment' किण्वं, नग्नहूः, कारोत्तरः, मंडः; 'company of l.-drinkers' आपानं, पानगोष्ठिका; 'drinking l.' सरकः, अनुतर्षणं, मद्यपानं. 2 Liquid, q. v. 3 पेयं.

Lisp, v. i. स्खरभंगेन-अस्पष्टं-वद् 1 P or वच् 2 P or उच्चर् c. or उदीर् c., अव्यक्तं वद्, अस्फुटवाचा जल्प् 1 P, स्खल् 1 P. -s., -ing, s. गद्गदवाच् f. -वाक्यं, अस्फुटोच्चारणं, अव्यक्तवर्णं जल्पितं, स्खलितवाच्. -er, s. अस्पष्टवाच्, गद्गदवाच्, अस्फुटवादिन्, all m. -ingly, adv. अस्फुटवाचा, गद्गदवाचा.

Lissom, a. See Flexible.

List, s. आवलि-ली f., पंक्ति f., परिसंख्या, परिगणना, अनुक्रमणिका, सूचि-ची f.; 'a l. of names' नामावली; 'a l. of errata' शुद्धिपत्रं. 2 वस्त्रखंडः. 3 वस्त्रप्रांतः, दशाः, वस्तयः (pl.). 4 युद्ध-रण-भूमि f., रणः, रणाजिरं, मल्लभूः-भूमिः; 'enter or take the l.s' रणार्थं सज्जीभू 1 P or सन्नद्ध-a. भू. -v. t. वस्त्रखंडैः आच्छद् 10. 2 वस्त्रखंडान् संसिव् 4 P. 3 गणनापत्रे नामानि अभिलिख् 6 P or आरुह् c. (रोपयति). 4 Listen, q. v. -v. i. इष् 6 P, रुच् 1 A, अभिलष् 1,4 P; See Like. 2 आ-अव-लंब् 1 A, प्रवणीभू 1 P; See Lean.-Listless,a. अनवहित, निरपेक्ष, उदासीन, प्रमादिन्, अनुत्सुक, निरुत्साह; अनिच्छु,निरीह, निरुद्योग, विरक्त, निःस्पृह. 2 जड, ग्लान; See Languid. -ly, adv. अनवधानेन, निरपेक्षं, उदासीन-

रत, निरुत्सुक, अनपेक्षक, अवश, नि:स्पृह. **-ness**, *s.* अनवधानं, अनपेक्षा, औदासीन्यं, अनौत्सुक्यं, विरक्ति *f.*, अनिच्छा, अनीहा, अस्पृहा, अनुत्साहः, अनास्था, आलस्य, मांद्यं.

Listen, *v. i.* श्रु 5 P, आकर्ण् 10, नि-शम् *c.*, कर्णं दा 3 U, अव-धा 3 U, अवहित-साव-धान-*a.* भू 1 P; 'l. now' अवधीयतामधुना, कर्णं देहि. 2 अनुवृत् 1 A, अनुरुध् 4 A. **-er**, *s.* श्रोतृ *m.*

Literal, *a.* मूल, मुख्य, प्रकृत, अरूपक; मूलार्थक, मुख्यार्थक, शब्द in comp. 2 यथाशब्द, शब्दार्थानुसारिन्, मूलपदानुसारिन्. 3 अक्षरमय (यी *f.*); 'l. meaning' प्रकृतार्थः; शब्दार्थः, मूलार्थः. **-ity**, *s.* मुख्यार्थः, प्रकृतार्थः, शब्दार्थः, मूलार्थः, अरूपकं. **-ly**, *adv.* मूलार्थानुसारेण, शब्दतः, शब्दशः, यथाशब्दं, अक्षरशः.

Literary, *a.* विद्या-साहित्य-संबंधिन्, विद्याविषयक, शास्त्र-ज्ञान- in comp.; 'l. work' शास्त्रग्रंथः; 'l. dispute' ज्ञानसंघर्षः. 2 (Literate) विद्यावत्, विद्यासंपन्न, विद्याविशिष्ट, विद्यानुरागिन्; विद्या-शास्त्र- in comp.; *See* **Learned**. **-Literature**, *s.* साहित्यं, विद्या, शास्त्रं; शास्त्रसमूहः; पुस्तकसमुदायः; 'dramatic l.' नाट्यपुस्तकसमूहः. **-Literati**, *s.* विद्वत्समाजः, पंडितवर्गः-गणः, विद्वद्वृंदं.

Lithe, *a.* शिथिल, मृदु, मिद्देलिम, सुखनाम्य.

Lithograph, *v. t.* शिलाया उपरि लिख् 6 P, शिलां रेखादिभिः मुद्र् 10 or अंक् 10. **-s.** शिला or पाषाण-लेखः or मुद्रा. **-er**, *s.* शिलालेखकः, शिलामुद्राकृत् *m.* **-y**, *s.* शिलालेखनविद्या, पाषाणलेखनं.

Lithontriptic, *a.* अश्मरीहर, अश्मरीघ्न (घ्नी *f.*).

Lithotomy, *s.* मूत्राश्मोच्छेदः.

Lithotripsy, *s.* अश्मरीसंघर्षः.

Litigant, *a.* विवदमान, विवादार्थिन्, कार्यार्थिन्, व्यावहारिक (की *f.*). **-s.** वादिन् *m.*, कार्यार्थी, व्यवहर्तृ *m.*, अर्थी, विवादार्थी. **-Litigate**, *v. i.* वि-वद् 1 A, व्यव-हृ 1 P. **-v. t.** विवादास्पदीकृ 8 U. **-ed**, *a.* वाद, ग्रस्त, विवादास्पदीकृत-भूत, वादानुगत. **-ion**, *s* वि-,वादः, व्यवहारः. **-Litigious**, *a.* विवादप्रिय-शील, विवादार्थिन्, विवादपर-रत-आसक्त.

Litter, *s* शिबिका, याप्ययानं. 2 तृणशय्या, तृणसंस्तरः-शयनं. 3 शावकगणः-संघः. 4 द्रव्यसंकरः, व्यस्तता. **-v. t.** शावकजननं कृ 8, 4 A, or उत्पद् *c.* 2 तृणेन आवृ 5 U or आस्तृ 5 U. 3 इतस्ततःक्षिप् 6 P or विकिर् 6 P.

Little, *a.* अल्प, अल्पक, क्षुद्र, लघु, अणु, सूक्ष्म, न्हस्व; अनुरूप, वृद्ध, अणुक, क्षुद्र-अल्प-लघु-परिमाण; अल्प-मात्र, अबहु; स्वल्प, स्तोक, अप्रचुर, ईषत्, in comp. 2 क्षुद्रतनु, अल्पकाय-शरीर-तनु. 3 क्षुद्र-लघु-मति, कृपण-मनस्-चेतस्-बुद्धि; (as a diminutive) ex. by the suffix क; 'a l. girl' बालिका; 'a l. boy' बालकः; 'a l. cottage' कुटिका; 'very l.' अल्पिष्ठ, अत्यल्प; 'a l. wealth' द्रव्य-लेशः-लवः, स्तोकं द्रव्यं; 'a l. finger' कनिष्ठांगुलि *f.*; 'for a l. while' कंचित्कालं. **-adv.** 'a l.' ईषत्, किंचित्, स्तोकं, मनाक्, अभूरि, अबहु; oft. by आ, दुर, ईषत् in comp.; 'a l. split' दरदलित; 'not a l.' भृशं, अत्यंतं; 'a l. distant' अनतिदूर, ईषद्दूर; 'l. less' ईषदून, किंचिन्न्यून, कल्प-प्राय- in comp.; 'a l. less than dead' मृतप्रायकल्प; 'l.-minded' कृपणबुद्धि, क्षुद्र-लघु-चेतस्. **-s.** अल्पं, किंचित्, स्तोकं, अल्प-स्तोक-भागः, अल्पांशः, किंचन, मात्रा, लवः; कणः, लेशः; अल्पमात्रं; 'by l. and l.' अल्पाल्पं, अल्पशः, स्तोकशः. **-ness**, *s.* अल्पता, तनुता, लघुता, स्तोकता, &c. 2 (Of mind) दीनता, कार्पण्यं, क्षुद्रता, कदर्यता, दैन्यं.

Littoral, *a.* तटस्थ, तीरस्थ.

Liturgy, *s.* प्रार्थनामार्गः, भक्तिमार्गः.

Live, *v. i.* वस् 1 P, नि-प्रति-°; अधिवस्, अध्यास् 2 A, अधि-ष्ठा 1 P (with acc.) 2 जीव् 1 P, प्र-अन् 2 P, श्वस् 2 P, भु pass. or 6 A, विद् 4 A, वृत् 1 A, 'here I l.' एषा स्थिये (U. 3); 'as long as you l.' यावज्जीवं, यावत्प्राणान् धारयसि or असुधारणं करोषि. 3 (On) उप-आ-जीव्, शरीरवृत्तिं-प्राणयात्रां-कॢप् *c.* or निर्वृत् *c.* or कृ 8 U. प्राणधारणं कृ, निर्वह् 1 P; 'l.-ing on fish' मत्स्याजीव, मत्स्योपजीविन्; sometimes by वृत्ति *f.*; 'l ed on fruits, roots, &c.' फलमूलादिभिः वृत्तिमकरोत्; 'l. ing on the leaves of trees falling down of themselves' स्वयंविशीर्णद्रुमपर्णवृत्तिता (K. v. 28); 'l.s on wild fruits' वन्यफलैः शरीरवृत्तिं निर्वर्तयति. 4 जीवितं-कालं गम् *c.* (गमयति) or या *c.* (यापयति) or नी 1 P or अतिवह् *c.* or वृत् *c.*; 'l. through time' चिरस्थायिन्-अमर-*a.* भू 1 P. **-a.** सजीव; *See* **Living** below; 'l.-long' दीर्घ-चिर-कालीन, चिरस्थायिन्; 'l.-stock' जीवधनं. **-ing**, *a.* सजीव, जीवित, प्राणभृत्, सचेतन, प्राणधारिन्, चेतनावत्, सचेष्ट, सप्राण; 'a l. being' प्राणी, जीवी, जंतुः, प्राणभृत्, शरीरी, जीवः, देही, चेतनः, सत्वं; 'world of the l.' जीवलोकः. 2 वर्तमान, विद्यमान, विराजमान; 'a l. poet' वर्तमानकविः. 3 स्थायिन्, अनश्वर, अव्ययपरिणामिन्, अविनाशिन्, अजर. अमर

(spring &c.). 4 आ-उप-जीविन्, आजीव or वृत्ति in comp.; 'l. by arms ' शस्त्रोपजीविन्; 'l. by agriculture' कृष्याजीव; 'l. wickedly ' दुर्वृत्ति, दुर्वृत्त, पापाचरित, पापवृत्ति; 'l. by beggary ' याचकवृत्ति, &c.; 'within l. memory ' स्मार्ते काले; 'a l. sacrifice ' जीवोपहारः; 'a l. death ' जीवितमरणं. -s. जीवनं, प्राणधारणं, वासः. 2 जीविका, आ-उप°-; आजीवः, वृत्ति f., जीवनं, वर्तनं, आ-उप-जीवनं, जीवनोपायः, जीवन-जीव-साधनं, प्राण-शरीर-यात्रा, निर्वाहः, प्राण-जीव-निर्वाहः, प्राण-शरीर-स्थिति f., जीवनार्थः. 3 धर्माध्यापकवृत्तिः, धर्मदायः; 'good l. ' सुभोजनं, मिष्टाहारः, परमान्नभोजनं; 'bad l. ' कदन्नभोजनं. -**Livelihood,** s. जीविका, वृत्तिः, जीवनं, प्राणयात्रा; *See* **Living** above; 'bare l. ' ग्रासाच्छादनमात्र, अन्नोदकमात्रं, दिननिर्वाहः. -**Lively,** a. सोल्लास, उल्लासिन्, आनंदिन्, प्रहृष्ट, उल्लसित, प्रमुदित, आनंद-उल्लास-वृत्ति. 2 स-सत्त्व, सोत्साह, उत्साहशील, तेजस्विन्, तीव्र, तीक्ष्ण; ' of a l. countenance ' प्रफुल्लवदन, हास्यमुख (स्त्री f.), सुहास्यवदन, प्रसन्नमुख. -*adv.* सोत्साहं, प्रफुल्लतया, सोल्लासं. -**ness,** s. उल्लासः, प्र-,हर्षः, आनंदः, प्रफुल्लता, उत्साहः, तेजस् n., सत्त्वं.

Liver, s. यकृत् n., कालखंडं; कालकं, कालेयं.

Livery, s. वेषः, कुल-आर्य-वेषः; 'l.-man ' कुलवेशधारिन् m., पौरवेशः; 'l.-stable' अश्वपोषणशाला, अश्वशाला.

Livid, a. नील, नीलवर्ण, सीसकवर्ण, नीलकृष्ण. -**ity,** -**ness,** s. नीलवर्णः, नीलिमन् m., सीसकवर्णः.

Lixivium, s. क्षारजलं-अंबु n. -**Lixivious,** a. क्षाराक्त, क्षारविशिष्ट.

Lizard, s. सरटः-टुः, कृकं(कु)लासः-शः, प्रतिसूर्यः-र्यकः; ' house-l. ' गृहगोधा-धिका, मुसा(श)ली, ज्येष्ठा-ष्ठी, गृहालिका.

Lo, *interj.* पश्य, प्रेक्षस्व.

Load, s. भारः, भरः; धुर् f, पर्याहारः. 2 बाधा, पीडा, दुःखं; कष्टं; ' the body is a l. (to me)' भारः कायः, भारभूतं शरीरं, कष्टप्रायं शरीरं; ' l. s of gold ' सुवर्णभाराः; ' bearing a l.' भारवाहन, भारसह, धुर्वह, धुरंधर. -*v. t.* भारं न्यस् 4 P or नि-धा 3 U or निविश् c. or आरुह् c. (रोपयति), भारेण पूर् 10, भारेण पीड् 10 or आक्रम् 1 U, 4 P, भाराक्रांत-*a.* कृ 8 U; ' trees l. ed with fruits' फलभाराक्रांता वृक्षाः; *See* **Bend** (*v. i.*). 2 (A gun) आग्नेयचूर्णेन पूर्, आग्नेयचूर्णं निविश् c. -**ed,** a. सभार, भाराक्रांत, भारग्रस्त, भारवत्, आरोपित-निवेशित-भार, धुरीण. 2 गर्भ in comp., पूर्ण, पूरित; 'l. with perfume ' परिमलाक्रांत, वासगर्भ, वासपूर्ण. -**ing,** भारारोपणं. 2 भारः.

Loadstone, s. अयस्कांतः, अयोमणिः, लोहकांतः, चुंबकः, लोहचुंबकः, चुंबकप्रस्तरः-मणिः.

Loaf, s. अपूपः, पूपः, पिष्टकः, करंभः. -*v. i.* कालापव्ययं कृ 8 U.

Loam, s. चिक्कण-स्निग्ध-मृत्तिका. -**y,** a. चिक्कण, मसृण.

Loan, s. ऋणं, ऋणदानं, धनप्रयोगः, आविहितकालात् द्रव्यप्रयोगः.

Loath, a. अनुत्सुक, अनिच्छु, वि-पराङ्-मुख (खी f.), विरक्त, अनिच्छत्, अकाम, निष्काम.

Loathe, v. t. गर्ह् 1, 10 A, गुप् desid. (जुगुप्सते), अत्यंतं द्विष् 2 U; *See* **Abhor**. -**ful,** -**some,** a. बीभत्स, अतिगर्हित, घृणाकारिन्, अतिगर्ह्य, कुत्सित, घृणार्ह, जुगुप्सावह. -**ing,** s. बीभत्सः, जुगुप्सा, घृणा, गर्हा, अतिनिर्वेदः-द्वेषः. -**ingly,** *adv.* सबीभत्सं, घृणापूर्वं.

Lob, s. स्थूलकायः, स्थूलशरीरः.

Lobby, s. समीपशाला, उपगृहं-शाला.

Lobe, s. (कर्णस्य) पालि f., पालिका, लतिका. 2 भागः, अंशः. -**ed,** a. पालिविशिष्ट.

Local, a. स्थानिक (की f.), स्थानीय, दैशिक (की f.), देश्य, देशीय, देश-स्थान- in comp.; 'l. usage' देशाचारः; 'l. news ' इहवृत्तं. 2 एक-देशीय-देशिन्-स्थानिक. -**ity,** s. स्थानं, प्र-,देशः, स्थलं. -**ly,** *adv.* स्थानविषये, स्थानमुद्दिश्य.

Locate, v. t. निविश् c., नि-धा 3 U, स्था c. (स्थापयति), विन्यस् 4 U; *See* **Place**. -**ion,** s. स्थापनं, निवेशनं, विन्यासः. 2 स्थानं, प्रतिष्ठानं, अधिकरणं. -**ive,** s. सप्तमी विभक्तिः, अधिकरणं.

Lock, s. तालः-लकं, तालयंत्रं. 2 (Of hair) पाशः, कलापः, केशकलापः-पाशः, अलकः; शिखंडकः, काकपक्षः (of young persons); चूडा, शिखा. 3 जलस्तंभनी-बंधनी 4 आलिंगनं, आश्लेषः, उपगूहनं. -*v. t.* तालेन बंध् 9 P or पि-धा 3 U or निरुध् 7 U. 2 रुध्, बंध्, संयम् 1 A. 3 गाढं आलिंग् 1 P, दृढं परिष्वंज् 1 A; *See* **Clasp, Embrace**; 'l. ed in sleep ' निद्रालीढ, निद्रानिमीलितलोचन; 'l.-jaw,' 'l. ed jaw ' हनुस्तंभः-ग्रहः. -**er,** s. तालकसनाथः कोष्ठः, संपुटकः.

Locket, s. कुडुपः.

Locomotion, s. स्थानांतर-स्थलांतर-गमनं, चलनं, गमनागमनं. 2 चलन-गमनागमन-शक्ति f. -**Locomotive,** a. चल, चलन, जंगम, चलनशील, गतिविशिष्ट, चलनशक्तिक, संचारिन्.

Locus, s. मिथिः, मिथानं.

Locust, *s.* शल(र)भः, तिडिः.
Locution, *s.* वाक्यं, उक्ति *f.*, वचनं.
Lode, *s.* धातुरेखा.
Lodh, *s.* लोध्रः, गालवः, शा(सा)बरः, तिरीटः, तिल्वः, मार्जनः.
Lodge, *v. i.* निवस् 1 P, नि-वस् 4 P, आश्रि 1 U, अव-स्था 1 A, स्था 1 P, वृत् 1 A, लग् 1 P, अनुसंप्र-संप्र- pass. —*v. t.* नि-धा 3 U, न्यस् 4 U, निविश् c., स्था c. (स्थापयति), *See* **Place.** 2 वद् c., आ-अर्थ कृ 3 U, वासस्थानं कृ; 'to l. a suit or complaint' राज्ञे निविद् c. —*s.* उपकुटी, उटजनकुटी. 2 **Lodging,** q. v. —**ing,** *s.* वासकुटी-स्थानं, वासः, नि-आ-वासः, वसति *f.*, नि-आ-लयः, आ-सं-श्रयः, निवेशनं; *See* **House.** —**ment,** *s.* निवेशनं, स्थापनं. 2 अव-सं-स्थिति *f.* 3 निवेशः-शनं, समावासः.
Loft, *s.* अट्टः, चन्द्रशाला, शिरोगृहं, उपरिकोष्ठः.
Lofty, *a.* उन्नत, तुंग, उच्च, उदग्र, उच्छ्रित, प्रांशु, प्रोच्छ्राय. 2 उद्धत, महोद्धत, दृप्त, अवलिप्त, साटोप, महोद्धत, गर्वोद्धत; *See* **High.** 3 प्रौढ, उदात्त, धीर, गंभीर, गुरु, महत्. —**ly,** *adv.* उच्चैः, ऊर्ध्वं. 2 सगर्वं, साटोपं, सदर्पं, उद्धतं. —**ness,** *s.* (lit.) उन्नति *f.*, उत्सेधः, उच्छ्रायः, तुंगता, उच्चत्वं, प्रांशुता. 2 औद्धत्यं, आटोपः, अवलेपः, दर्पः, गर्वः, अभिमानः. 3 प्रौढता, गाम्भीर्यं, धीरता, गुरुत्वं, महत्त्वं, माहात्म्यं, उत्कर्षः, उदात्तत्वं, उन्नतिः.
Log, *s.* काष्ठं, वृक्ष-काष्ठ-खंडः-डं, स्थूल-वृहत्काष्ठं. 2 गतिमापः.
Logarithm, *s.* संवर्गमानं, घातमानापकः.
Logger-head, *s.* स्थूल-जड-बुद्धिः, मूढः, मूर्खः, जडः; 'to be at l. s' विवद् 1 A, कलि-कलहं-आरभ् 1 A. —**ed,** *a.* स्थूल or जड-धी or बुद्धि.
Logic, *s.* तर्कः, न्यायः, आन्वीक्षिकी, न्याय or तर्क-शास्त्रं or विद्या, युक्तिवादः. —**al,** *a.* तार्किक नैयायिक-यौक्तिक-(की *f.*), तर्कशास्त्रविषयक. 2 तर्क-न्याय-युक्ति-सिद्ध, तर्क-न्यायसंमत, न्यायानुसारिन्, तर्कानुरूप; 'a l. conclusion' सिद्धान्तः. —**ally,** *adv.* न्यायतः, यथान्यायं, तर्कानुसारेण, न्यायशास्त्रानुरूपं. —**ian,** *s.* नैयायिकः, तार्किकः, तर्किन् *m.*, न्यायविद् *m.*, तर्क-न्याय-शास्त्रज्ञः.
Logomachy, *s.* वाग्युद्धं, वाक्कलहः, वितंडा. 2 शब्दविवादः.
Loin, *s.* श्रोणि-णी *f*, कटि-टी *f.*, नितंबः, जघनं, स्फिच् *f.* (hip & l. s); श्रोणिफलकं, कटी-श्रोणि-तटं; 'gird the l. s' परिकरं बंध् 9 P, कटिं बंध्; 'born from one's own l. s' अंगज, अंगजात.
Loiter, *v. i.* विलंब् 1 A, मंथायते (D.), कालं क्षिप् 6 P or हृ 1 P; 'l. about' मंद मंदं चर्-वृ 1 P, इतस्ततः मंदं भ्रम् 1, 4 P, चिरं अव-स्था 1 A. —**er,** *s.* कालक्षेपकः, अलसः, विलंबिन् *m.*, मंथरगतिः, चिरक्रियः. —**ing,** *s.* विलंबनं, मंथरत्वं, कालक्षेपः; *See* **Linger,**-**er.**
Loll, *v. i.* आलस्येन अवलंब् 1 A or आश्रि 1 U or संविश् 6 P or शी 2 A. —*v. t.* लल् 10 (लालयति); 'l. the tongue' जिह्वां लल् or चलिज् 8 U. —**ing,** *s.* लालनं.
Lone, Lonely, *a.* विविक्त, निर्जन, विजन, निर्मनुष्य, निभृत, मनुष्य-हीन-संचार, एकान्त, निर्मानुष (षी *f.*). 2 असहाय, असहाय, एकाकिन्, एक, केवल. 3 विविक्त-प्रिय, विविक्तसेविन्; 'a l. place' विविक्तं, निर्जनदेशः; 'in a l. place' विविक्ते, विजने, रहसि, निःशलाकं, रहः, उपांशु. —**liness,** *s.* विविक्तं, निर्जनता, विजनता. 2 एकाकिता, असहायता. 3 विविक्तसेवा-रुचि *f.*, प्रीति *f.* —**some,** *a.* निर्जन, दारुण, भीषण, घोर.
Long, *v. i.* (for) (अत्यंतं) स्पृह् 10 (with dat.), इष् 6 P, अभिलष् 1, 4 P, कांक्ष् 1 P, ईह् 1 A, वांछ् 1 P, आशंस् 1 A; *See* **Wish;** लुभ् 4 P, गृध् 4 P; sometimes ex. by denom. in य or काम्य; 'l. s for a son' पुत्रीयति, पुत्रकाम्यति; पुत्रलिप्सति, &c. 2 उत्कंठावती भू 1 P, दोहदिनी भू. —*a.* दीर्घ, आयत, आयामवत्, लंब, दीर्घपरिमाण, दीर्घाकार; विस्तृत, विस्तीर्ण. 2 चिर in comp., दीर्घ-चिर-कालीन, दीर्घ-चिर-कालिक (की *f.*), चिरंतन (नी *f.*), चिरस्थायिन्- स्थित, चिरस्थाय-दीर्घकालस्थायिन्. 3 दूर, वि-सु-दूर. 4 दीर्घसूत्र, चिरक्रिय, विलंबकारिन्. 5 परि-प्र-माण, मात्र, मित, परिमित in comp.; 'three fingers l.' त्र्यंगुलमात्र-परिमाण, त्र्यंगुलमित, त्र्यंगुल; 'being a l. way off' दूरस्थ, दूरस्थायिन्; 'a l. period दीर्घ-चिर-कालः; 'for a l. time' चिरं, दीर्घं, चिराय; *See* (*adv.*); 'the l. run' आयति *f.*; 'a l. vowel' दीर्घस्वरः. —*adv.* चिरं, चिरेण, चिराय, दीर्घ-चिर-कालं, दीर्घं, बहुकालं, चिरदिवसं. 2 दूरं, दूरे, दूरपर्यंतं; 'l. absent' चिरप्रवासिन्, चिरगत; 'l. sick' दीर्घ-चिर-रोगिन्; 'living l.' चिरजीविन्, आयुष्मत्; 'l. since left' चिरत्यक्त, &c.; 'how l.' कियच्चिरं, कियंतं कालं; कियत्कालं; 'how l. after' कियच्चिरेण; 'not very l.' नातिचिरं; 'very l.' सुचिरं; 'l. ago' प्राचीन, पूर्वमेव, अतीतपूर्वकाले; 'not l. ago' नातिचिरात् प्राक्, अनतिपूर्वं; 'ere l.' अचिरेण, अचिरात्; 'as l. as' 'so l.' यावत्-तावत्; 'as l. as one lives' यावज्जीवं, आमरणात्; 'the whole year l.' आवर्षांतात्, वर्षपर्यंतं; 'l. after' बहोः कालात्, दीर्घकालानंतरं. In comp. words ex. by दीर्घ, चिर, लंब, दूर, आयत; 'l.-armed' दीर्घभुज, लंबहस्त; 'l.-bellied' लंबोदर;

'l.-continuing' चिरस्थायिन्; 'l.-eyed' आयताक्ष,-आयतलोचन; 'l.-headed' –दूरदर्शिन्,-दीर्घदर्शिन्, पटु; 'l.-lasting' चिरस्थायिन्, चिरस्थायिन्; *See* (*a.*); 'l.-legged' दीर्घजंघ, करभोरु, करभोरू; 'l.-lived' चिर(र)-जीविन्, दीर्घायुस्, चिरायुस्, चिरजीविन्-जीवित, आयुष्मत्; 'l. pepper' कृष्णा, उपकुल्या, वैदेही, मागधी, चपला, कणा, उ(ऊ)षणा, पिप्पलिः-ली, शौंडी, कोला, तीक्ष्णतंडुली, कपिवल्ली, कोलवल्ली, श्रेयसी, वशिरः; 'l. pepper root' ग्रंथिकं, पिप्पलीमूलं, चटकाशिरस् *n.*; 'l.-sighted' दूर-दीर्घ-दृष्टि; 'l.-suffering' सहिष्णु, क्षमाशील, क्षमिन्, बहुक्षम; (*s.*) क्षमा, सहिष्णुता, क्षमाशीलता. –er, *a.* दीर्घतर; 'any l.' अतःपरं-ऊर्ध्वं, इतः परं; 'why delay any l.' किमित्यधुना विलंब्यते. –ing, *a.* अत्यभिलाषिन्, अत्याकांक्षिन्, कुतूहलिन्,बहुस्पृह,उत्कंठित उत्कट, लालस, अत्युत्सुक; 'a l. desire' उत्कटेच्छा; 'a l. woman' दोहदवती; दोहदवती. –*s.* अत्यभिलाषः, अतिस्पृहा-वांछा, अत्याकांक्षा, उत्कंठा, लालसा, औत्सुक्यं, अतिलिप्सा; इच्छा; कामः, मनोरथः, स्पृहा, तृष्णा, आकांक्षा; 'the l. of a pregnant woman' दोहदः, गर्भलक्षणं. –ingly, *adv.* सस्पृहं, सतृष्णं, सोत्सुकं, सोत्कंठं. –Longanimity, *s.* क्षमा, क्षांति *f.* –Longeval,-Longevous, *a.* चिरंजीविन्; *See* Long-lived. –Longevity, *s.* दीर्घायुः; चिरायुः. –Longmetry, *s.* दैर्घ्यमानं. –Length, *s.* दैर्घ्यं, दीर्घता-त्वं, आयामः, द्राघिमन् *m.*, आरोहः, आयति *f.*, विस्तारः, आनाहः, विस्तृति *f.*, वितति *f.* 2 मात्रा, अवधिः, मर्यादा, पर्यंतः; 'my rudeness (impudence) was carried to the l. of taking up arms' आयुध परिग्रहं यावदुत्सन्नो दुर्योगः (U. ö). 3 मार्गं, प्र-परि-मार्गं. 4 चिर-दीर्घ-कालः, कालदैर्घ्यं; 'to such a l.' एतावत्पर्यंतं, यावत् (with acc.); 'for a l. of time' चिरं, चिरकालं; 'to a great l.' अतिमात्रं, अतिमर्यादं; 'at l.' सविस्तरं, विस्तरेण, सुविस्तरेण, विस्तरतः, असंक्षेपतः. 2 अंते, अंततः, शेषे, चिरकालस्य, चिरस्य, अतीतदीर्घकाले. 'spread at l.' विस्तीर्ण; 'to lie at full l.' दंडवत् पत् 1 P. –en, *v. t.* दीर्घीकृ 8 U, प्र-वि-तन् 8 U, विस्तृ c., प्र-वि-सृ c., आयम् 1 A, आयती-वितती-कृ. –*v. i.* विस्तृ-वितन् pass., दीर्घीभू. –wise, *adv.* अन्वायामं, अनुदैर्घ्यं, अनु in comp. –y, *a.* विस्तीर्ण, दीर्घ, आयत, सविस्तर, असंक्षिप्त.

Longitude, *s.* दूरता, द्राघिमन् *m.* 2 रेखांशः; (of heavenly objects) भोगः; 'circle of l.' रेखावृत्तं. –Longitudinal, *a.* अनुदैर्घ्य, अन्वायत.

Looby, *s.* स्थूलकायः, जाल्मः, मूढः, जडः.

Look, (at), *v. i.* दृश् 1 P, अव-वि-आ-लोक् 1 A, 10, ईक्ष् 1 A, निरूप् 10, निर्वर्ण् 10, दृष्टिं कृ 8 U or क्षिप् 6 P, लक्ष् 10; 'l. intently at' नयनैः-दृष्टिभिः-पा 1 P, पिबे 1 P, (ता राघवं दृष्टिभिरापिबंत्यः &c. R. vii. 12). 2 भा 2 P, आ-प्रति-, लक्ष्-दृश्-pass.; oft. by वदन, मुख, आकार in comp.; 'she l. s sad' विषण्णा लक्ष्यते or आभाति, &c.; 'that l.s like wantonness' उद्धतचरितोचितं (Mal. 2); 'l. ing dejected' विषण्णवदन, म्लानमुख, &c.; 'l. well' शुभ् 1 A; 'l. now' पश्य, पश्य-. –about, परितो वीक्ष्, अनु-दृश् 4 P. –after, अपेक्ष्, रक्ष् 1 P, पा c. (पालयति); *See* 'Take care' under Care; योगक्षेमं वह् 1 U, (कुल्याया मे जनन्या योगक्षेमं वहस्व M. 4). 2 अन्विष्, निरूप् 10, मृग् 10 A. –down, अवेक्ष्, अधो दृश्; 'l. down upon' अवमन् 4 A, उपेक्ष्; *See* Contemn. –for, प्रतीक्ष् 1 A, अपेक्ष्, प्रति-इष् 6 P. *See* Expect. 2. अन्विष्, इष्; *See* Search. –in, आविश् 1 P, आत्मानं दृश् c., प्रकटीभू; 'l. in the face' संमुखी-अभिमुखी-भू (with gen.); *See* Face. –into, अव-सं-निर्-परि-ईक्ष्, अनुसं-धा 3 U, निरूप्; *See* Examine; 'l. into the matter very closely' अतिनिपुणमपेक्ष्यतां सौर्यः. –on, प्रेक्ष्, मिष् 6 P; मिषतामाच्छिनत्ति नः (K. ii. 46) 'snatches (the oblation), we helplessly l. -ing on' 2 (Upon) मन् 4 A, गण् 10; *See* Consider. –out, अव-धा 3 U, सावधान-*a.* भू 1 P. –over, संदृश्-ईक्ष्; निरूप्, निरीक्ष्. –to, सं-वि-ईक्ष्, अवधानं दा 3 U; ex. by 'Care' q. v. 2 आ अव-लंब् 1 A, आश्रि 1 U. –up, ऊर्ध्वं, दृश् or ईक्ष्, उद्वीक्ष्, उन्मुखीभू; 'l. ing up to heaven' नभोदृष्टि, गगनदृष्टि; 'l. up to' प्रतीक्ष्, उद्-दृश्, मन्, गण्, परिकल्प् c., 'the people l. up to you as their saviour' आत्मनो रक्षकत्वेन त्वामेवामी जनाः प्रतीक्षंते, गणयंति or परिकल्पयंति. –*s.* दृष्टि *f.*, दर्शनं, ईक्षणं, वीक्षणं, प्रेक्षणं, वीक्षितं, विलोकितं, आ-वि-अव-लोकनं, दृष्टिपातः, दृक्पातः. 2 रूपं, आकारः, आकृति *f.*, दर्शनं, आलोकः, चर्या, आभा, छाया, वदनाकारः, मुखच्छाया, मुखं, वदनं; 'a l. of displeasure' अकृपादृष्टिः; 'side-l.' कटाक्षः; अपांगदर्शनं; 'l.-out' अपेक्षा, समीक्षा, अवधानं; 'to be on the l.-out' अपेक्ष्, अव-धा 3 U, अवहित-*a.* भू. –er, *s.* द्रष्टृ *m.*, दर्शिन् *m.*, वीक्षकः. 2 (On) प्रेक्षकः, प्रेक्षमाणः. –ing, *a.* पश्यत्, दर्शिन्;

घृष्टि, नयन in comp.; 'l. in all directions, विश्वग्दृष्टि, सर्वतो दृष्टिः, 'l. up' उन्मुख, ऊर्ध्वदृष्टि 'l. well' सुभ-सुदर्शन, सुरूप, शोभनाकार, प्रेक्षणीय, शुभानन. -s. दृष्टि, विलोकनं, वीक्षणं, निर्वर्णनं, आलोकः, &c. *See* (*s.*) above; 'l.-glass' आदर्शः, मुकुरः, दर्पणः.

Loom, *s.* वेमन् *m.*, वेमः, वाय(प)दंडः, तंत्रवायः. -*v. i.* अस्पष्टरूपेण दृश् pass., दूरे वृत् 1 A or स्था 1 P.

Loon, *s.* दुर्जनः, जाल्मः, कितवः, धूर्तः.

Loop, *s.* शिक्यं, काचः. 2 पाशः, पुटः. 3 छिद्रं, रंध्रं; 'suspended in a l.' काचित, शिक्यित; 'l.-hole' छिद्रं, रंध्रं, गवाक्षः, जालं; निर्गमः, निर्गमद्वारं, अपक्रमः; मुक्ति *f.*, मोक्षः.

Loose, *a.* शिथिल, प्र-श्लथ, स्रस्त, विगलित, चलित, मुक्त 2 अबद्ध, उद्ग्रथित, उत्सूत्र, बंधनरहित-शून्य, उद्दाम, प्रमुक्त. 3 विरल, असंहत, अदृढसंधि. 4 अव्यवस्थित, अनियत, अनिर्णीत, संदिग्ध, असंक्षिप्त; अस्थिर. 5 असंबद्ध, निःसंग, निरन्वय. 6 उच्छृंखल, निर्मर्याद, अनवस्थ, दुर्वृत्त, व्यभिचारिन्, व्यसनिन्, दुराचार. 7 गर्ह्य, मिथ्य, अश्लील; 'l. conduct' दुराचारः, व्यसनं, नीतिभ्रंशः, 'a l. man' लंपटः, व्यसनिन् *m.* 'a l. woman' रंडकी, पुंश्चली, भ्रष्टा; 'let l.' मुच् 6 P; *See* (*v.*); 'break l.' बंधनं भिद् or छिद् 7 P, बंधनात् भ्रंश् 1 A, 4 P. -*v. t.*, -**en,** *v. t.* शिथिलयति (D.), शिथिलीकृ 8 U, श्र(श्रं)थ्-श्लथ् 1 P, 10 (श्लथयति), स्रंस् c., श्लथीकृ. 2 मुच् 6 P or c., वि-निर्-उत्°; मोक्ष् 10, विसृज् 6 P or c., बंधनात् मुच्. 3 उद्-ग्रंथ् 9 P, उद्-अव-मुच्, वियुज् 7 A, 10, विश्लिष् c., विसं-धा 3 U. -*v. i.* -**en,** शिथिलीभू 1 P, श्र(श्रं)थ् 1 A, स्रंस् 1 A, मल्ल् 1 P, शिथिलायते (D.) -*adv.* -**ly,** *adv.* शिथिलं, श्लथं, अदृढं, विरलं, असंहतं, अनियतं; दुर्वृत्तवत्, निर्मर्यादं; 'l. hanging matted hair' श्लथलंबिन्यः जटाः; 'hanging l.' स्रस्त. -**ing,** -**ening,** *s.* शिथिलीकरणं, मोचनं, मोक्षणं, मुक्ति *f.*, श्लथनं. -**ness,** *s.* शैथिल्यं, प्र-,श्लथः, स्रंसः, श्लथता, स्रस्तता, अदृढता, अनियतता, विरलता, व्यसनिता, दुराचारः, अनवस्था, लांपट्यं, व्यभिचारः; *See* **Laxity.**

Lop, *v. t.* छिद् 7 P, कृत् 6 P, लू 9 P; *See* **Cut,** 2 आ-अव-लंब् c. -*v. i.* आ-अव-लंब् 1 A. -**per,** *s.* **Cutter,** q. v.

Lopsided, *a.* एकपार्श्वे पतयालु.

Loquacious, *a.* वावदूक, वाचाल-ट, मुखर; *See* **Garrulous.** -**ly,** *adv.* वाचालतया. -**ness,** -**Loquacity,** *s.* वावदूकता, वाचालता, बहुभाषित्वं, जल्पकता, मौखर्य.

Lord, *s.* ईशः, प्रभुः, ईश्वरः, स्वामिन् *m.*, अधिपः, पतिः, ईशितृ *m.*, अधिभूः, नायकः, नेतृ *m.*, भर्तृ *m.*, नाथः, इंद्रः in comp.; राजन् *m.* परिवृढः, इभ्यः, धानिन् *m.* आढ्यः; 'to be l. of' प्र-भू 1 P, ईश् 2 A, (with gen.); *See* **Master;** 'supreme l.' सर्वेश्वरः, अधिराजः, नरेंद्रः, क्षितिपतिः, स्वर्गाधिपः, जगन्नाथः-नायकः, &c. 2 (Title of address) देवः, महाराजः, स्वामिन् *m.*, आर्यपुत्रः (by wives) भर्तृ *m.* (by servants &c.). 3 परमेश्वरः, भगवान्, प्रभुः, ईश्वरः. -*v. i.* (सदर्प-सगर्व) ईश् or शास् 2 P. -**like,** -**ly,** *a.* राजोचित, प्रभुयोग्य, राजसदृश (शी *f.*), राजार्ह, ईश्वरीय, ऐश्वर (री *f.*) 2 ओजस्विन्, दीप्तिमत्, तेजस्विन्, *See* **Majestic.** 3 धृष्ट, अवलिप्त, ऐश्वर्यमत्त, दृप्त, गर्वित, उत्सिक्त; *See* **Haughty.** -*adv.* सदर्प, सदर्पं, उद्धतं, ऐश्वर्यमदेन. -**ship,** *s.* देवः, &c.; *See* above; 'his l.' तत्रभवान्; महाराजः; 'your l.' अत्रभवान्, देवः, &c. 2 प्रभुत्वं, स्वामित्वं, ऐश्वर्यं, अधिकारः. 3 राज्यं, विषयः.

Lore, *s.* विद्या, ज्ञानं; *See* **Learning.**

Loricate, *v. t.* कवचेन-पटलेन आस्तॄ 5 U or आच्छद् 10. -*a.* सकवच, पटलयुक्त.

Lorn, *a.* अनाथ, अशरण; *See* **Forlorn.**

Lose, *v. t.* अप-,हृ c., त्यज् 1 P, हा 3 P or c. (हापयति). 2 वियुज्-विहा-परिहा-pass., विनाकृ 8 U, (with instr.); भ्रंश् 1 A, 4 P, परि-प्र°, च्यु 1 A, प्र-वि-°, (with abl.); *See* **Deprived** also; 'he lost his life' प्राणैर्वियुक्तः, विगतासुर्बभूव, प्राणहीनः, प्राणैरहीयत; 'lost his realm' राज्याद्भ्रष्टः-च्युतः; 'l. s his friends' मित्रैर्वियुज्यते; 'he lost his wife' तत्पत्नी मृता, पत्न्या विरहितः. 3 (Destroy) नश् c., क्षि 1, 5 P or c., अप-चि 5 U, उच्छिद् 7 P, प्र-वि-ध्वंस् c. 4 (Not to find) ex. by नश् 4 P, प्रभ्रंश्; 'have you lost a camel' अपि युष्माकमुष्ट्रो नष्टः; 'the lost ring' नष्टमंगुलीयकं; 'l. the way' मार्गात् or पथः-भ्रंश् or च्यु or विचल् 1 P; 'he lost his way' प्रभ्रष्ट-नष्ट-पथः or उन्मार्गगामी अभूत्; 'lost his caste' जातिभ्रष्टः. 5 पराजि-पराभू-pass. (in battle &c.); 'l. one's wits' बुद्धिहीन-*a.* भू 'to l. time' कालं व्यर्थं नी 1 P or विक्षिप् 6 P, कालं हृ 1 P or या c. (यापयति), कालहरणं-कालक्षेपं कृ 8 U, विलंब् 1 A; 'l. good name' चारित्र्यं-कीर्तिं कलंकयति or मलिनयति (D.) or दुष् c. (दूषयति); 'l. one's consciousness' मुह् 4 P, मूर्छ् 1 P, चेतनां-संज्ञां हा, नष्टचेतन-लुप्तसंज्ञ- *a.* भू; 'we don't l. anything (in this way)' न नः किंचित् छिद्यते (S. B. 345), नास्माकं किमपि हीयते; 'to l. oneself in' आत्मान-

निरस्त- *a.* यू; *See* **Absorb.** **–er,** *s.* प्राप्तापायः, अपाय-हानि-सहः, पराजितः, लब्धहानिः,प्राप्तनाशः-क्षयः. **–Lost,** *a.* नष्ट, भ्रष्ट, च्युत, गत, भीत, हीन, त्यक्त, हृत, हारित, क्षीण, लुप्त; ' who has l. his office ' च्युताधिकारः, अधिकारभ्रष्टः, ' who has l. wealth ' अर्थहीनः, गतविभवः, नष्टार्थः; ' who has l. his way ' पथभ्रष्टः, उन्मार्गप्रवृत्तः, दिङ्मूढः; ' who has l. everything ' हृतसर्वस्वः; ' who has l. one eye ' अक्ष्णा अंधः, एकाक्षिविकलः; ' l. to shame ' त्यक्त-निरस्त-लज्ज, व्रीडाहीन, ' l. to sense of freedom ' स्वातंत्र्यरसानभिज्ञ; ' l. in meditation ' ध्यानपर-परायण-निष्ठ-मग्न, चिंतासक्त; ' the bone fell and was l. ' अस्थि निपतितं नयनविषयातीतं च; ' to be l. ' नश्, अंतर्-इ, तिरोधा pass., तिरोभू. **2** मोहित, मूढ, भ्रांत-चित्त-बुद्धि. **–Loss,** *s.* हानि *f.*, क्षयः, सं-उप-परिक्षयः, वि-,नाशः, अपायः, अपचयः, लोपः, भ्रंशः, च्युति *f.*, व्ययः, ध्वंसः, प्र-वि-ध्वंसः, वियोगः, अपहारः, अत्ययः, त्यागः, अलाभः, क्षति *f.* **2** पराजयः, पराभवः, भंगः; ' compensating l. ' क्षतिपूरणं; ' profit and l. ' लाभालाभौ; ' l. of time ' कालहरणं-क्षेपः, विलंबः; ' l. of caste ' जातिभ्रंशः; ' l. of army ' सैन्यनाशः, बलव्यसनं; ' to be at a l. ' मुह् 4 P; ' being at a l. what to do or say ' किंकर्तव्यता-किंवक्तव्यता-मूढ.

Lot, *s.* अंशः, वि-,भागः, उद्धारः. **2** भाग्यं, दैवं, भागधेयं, दैवगति *f.*, दशा, भवितव्यता; *See* **Fate. 3** गुटिका; ' fall to the l. of' आपत् 1 P, उपनम् 1 P, उप-स्था 1 U; आपतंति हि संसारपथमवतीर्णानामेते वृत्तांताः (Ka. 175); ' happiness will be your l. ' त्वं सुखभाग् भविष्यसि,तव सुखमुपनमेत्.

Loth, *a. See* **Loath.**

Lotion, *s.* धावनं, धावनौषधं.

Lottery, *s.*गुटिकापातः; गुटिकापातेन निर्णयः.

Lotus, *s.* पद्मं, कमलं, नलिनं, अरविंदं, उत्पलं, कुवलयं, सरसिजं, अब्जं, अंभोजं, महोत्पलं, शतपत्रं, सहस्रपत्रं, कुशेशयं, पंकेरुहं, पंकजं, सरोरुहं, तामरसं, सारसं सरसीरुहं, पुष्करं, अंभोरुहं, बिसप्रसूनं, राजीवं, अंबुजं; 'white l. ' पुंडरीकं, सितांभोजं; ' red l. ' कोकनदं, रक्तोत्पलं; ' blue l. ' इंदीवरं, नीलोत्पलं. **2** (The plant) नलिनी, कमलिनी, पद्मिनी, मृणालिनी, कुमुदिनी; ' l. stalk ' नालं-लः-ली-ला; ' l. fibre or film ' मृणालः-ली-लं, बिसं-सः; l.filament' किंजल्कः, केसरः(स)रः-रं, ' l. root or bulb ' करहाटः, शिफाकंदः, शालु(लू)कं; ' l. seed ' कमलाक्षः, पद्मबीजं; ' seed vessel of l.' बीजकोशः, वराटकः; ' new leaf of l. ' सं-वर्तिका, संवर्तः; 'an assemblage of l. es' षंडः, खंडः, पद्मषंडः.

Loud, *a.* उच्च, तार, महत्, ध्रुव, उत्ताल; महास्वन सुस्वर, महाध्वनिकर (री *f.*), महाबहु-घोष, महाशब्द, घोषण; ' a l. noise ' तारस्वरः, उच्चैर्घोषः, महाशब्दः-स्वनः, प्रणादः तुमुलरवः. **–adv., –ly,** *adv.* उच्चैः,तार-उच्चस्वरेण, मोच्चैः, महाशब्देन, महास्वनेन; ' stil l. er ' उच्चैस्तरां. **–ness,** *s.* उच्चता, महत्त्वं, उत्तालता, &c.

Lounge, *v. i.* उदास् 2 A, आलस्येन कालं क्षिप् 6 P or हृ 1 P, अलसीभू. **–er,** *s.* अलसजनः. कालक्षेपकः, उदासीनः, कार्यमुदः. **–ing,** *a.* अलस, मंद; *See* **Lazy;**' l. gait' मत्तेभगति *f.*-गमनं.

Louse, *s.* यूकः-का, केशकीटः; ' l.-egg ' लिक्षा. **–y,** *a.* बहुयूक, यूकापूर्ण, यूकोपद्रुत, सयूक.

Lout, *s.* ग्राम्यजनः, वृषलः, ग्रामीणः, स्थूलजनः. **–ish,** *a.* ग्राम्य, स्थूल, अशिष्ट,असभ्य, स्थूल-बुद्धि-मति.

Louver, *s.* धूमरंध्रं, धूमपथः-निर्गमः.

Lovage, *s.* अजमोदा, उग्रगंधा, ब्रह्मदर्भा, यवा(मा)निका.

Love, *s.* प्रेमन् *m. n.*, अभिलाषः, स्नेहः, रागः, वात्सल्यं, अनुरागः; प्रणयः, भावः, प्रीति *f.*, प्रेम-प्रीति-स्नेह-भावः (all with loc.); ' l. for God ' ईश्वरभक्ति *f.* **2** (Amorous) कामः, अनंगरागः, शृंगारः, शृंगारभावः, रति *f.*, रतिसुखं, मदनः.**3** (God of love) कामः, मदनः, स्मरः; *See* **Cupid. 4** दया, अनुकंपा. **5** रुचि *f.*, अभिरुचिः, आसक्ति *f.*, व्यसनं, अभिनिवेशः, प्रीतिः. **6** (Darling) प्रियः-या, प्रियतमः-मा, दयितः-ता; ' to fall or be in l. with ' स्निह् 4 P, अनुरंज् pass., भावं-अभिलाषं-बंध् 9 P or निविश् c., अनुरागवत्-बद्धभाव-मोहित- *a.* यू;' l.-affected ', ' l.-stricken ', ' under the influence of l.' अनंगतप्त-पीडित, कामार्त, कामवश, कामातुर, अनंगविधुर, मदनावस्थ, स्मराकुल, कामासक्त;' to make l.' विवाहार्थं मार्ग् 10 A or आराध् c.; ' gestures of l. ' शृंगारचेष्टा, हावः, विलासः, विभ्रमः, लीला, भावः; ' l.-knot ' प्रेमग्रंथिः-बंधः; ' l.-letter ' ' अनंग-मदन-लेखः, मन्मथलेखः; l.-match ' प्रेम-विवाह-संबंधः; ' l. quarrel ' प्रणय-प्रेम-प्रीति-कलहः; प्रणयकोपः; ' l.-sick ' कामार्त, कामातुर, कामपीडित, अनंगतप्त, विधुर, मदनविह्वल, ' l.-song ' शृंगारगीतं; ' l.-tale ' प्रेम-शृंगारकथा; ' l.-token ' प्रीतिलक्षणं, प्रेमाभिज्ञानं. **–v.** *t.* कम् 10 A (amorously); प्री-अनुरंज्-आसंज् pass.; gen. ex. by स्निह् (with loc.); बंध्, निविश् c. with (*s.*); ' the king l. s Sâgarikâ ' नृपः सागरि-

कार्यो मद्द्वाक्षराः, आसक्तचित्तः, कृतज्ञानः, &c. 2 रम् 1 A, आनंद् 1 P, जुष् 1 A, तुष् 4 P (with instr.); ex. by प्रिय-s.; *See* **Fond, Like**; ' I l. music ' संगीतमियोऽस्मि; ' l. knowledge ' विज्ञानलिप्सुरस्मि. **-able,** *a.* स्नेहार्ह, प्रिय. **-ed,** *a.* प्रिय, दयित, कांत, इष्ट, अभीप्सित, स्निग्ध, हृद्य, मनोऽभिमत. **-er,** *s.* (Amorous) कामुकः, कामिन् *m.*, कांतः, प्रियः, दयितः, वल्लभः, रमणः, नायकः, इष्टः, प्राणेशः, जीवितेशः. 2 प्रणयिन् *m.*, अनुरागिन् *m.*, निरतः, सेवी- प्रियः-in comp.; 'l. of knowledge' प्रियज्ञानः, ज्ञाननिरतः, ज्ञानेप्सुः; ' a l. of learned men' आगमवृद्धसेवी (R. vi. 41). **-ing,** *a.* प्रणयिन्, अनुरागवत्, सस्नेह, प्रणयवत्, प्रीतिमत्, वत्सल, अनुरक्त, अनुरागिन्, आसक्त, प्रिय, नि-,रत, सेविन् in comp; ' l. gambling ' द्यूतासक्त, द्यूतसेविन्; ' a l. husband ' अनुरागवान् पतिः; 'l. kindness' कृपा, दया, कारुण्यं, वात्सल्यं, प्रसादः, अनुग्रहः, स्नेहः, अनुकंपा. **-ingly,** *adv.* सप्रणयं, सस्नेहं, सानुरागं, स्नेहेन, वात्सल्यात्, प्रीतिपूर्वं. **-Lovely,** *a.* कांत, सुंदर (री *f.*), रुचिर, शोभन, सुभग, मनोज्ञ, मंजु, मंजुल, चारु, मनोरम, मनोहर, ललित, वाम, सुग्ध, कमनीय, अभिराम; *See* **Beautiful. -liness,** *s.* कांति *f.*, सौंदर्यं, शोभा, श्रीः, लावण्यं, सुभगता, चारुता; *See* **Beauty.**

Low, *a.* (Of place) नीच, निम्न, नत, नीचस्थ, अधःस्थ, अधस्तन (नी *f.*), अवाच्. 2 ह्रस्व, नीच, अल्पाकार, खर्व; अनुच्च, अतुंग. 3 नीच, अप-नि-कृष्ट, अधम, हीन, अधन्य, अवर, खल, क्षुद्र, अनार्य, वाच्य, गर्ह्य, अश्लील, निंद्य, (language); *See* **Mean**; ' a l. man अपसदः, नीचः, पृथग्जनः; जाल्मः, दुर्जनः. 4 (Voice) नीच, मंद्र, मंद, धीर, ग(गं)भीर. 5 (Price) स्वल्प, अल्प, मित, परिमित, अल्पमूल्य. 6 (L.-spirited) अवसन्न, खिन्न, उद्विग्न, म्लान, विषण्ण, विमनस्, दीन or उद्विग्न-मनस् or चेतस्; *See* **Dejected** 7 नम्र, विनीत, अनुद्धत, निरभिमान; *See* **Humble.** 8 निःसत्त्व, रूक्ष, असार, अपौष्टिक (की *f.*) (as food); ' of l. rank,' ' l.-born ' नीच, हीनजाति, अंत्यजातीय, नीचकुलज, हीनकुल, दुष्कुलीन, अधमजन्मन्, नीचवंशप्रसूत, हीनवर्ण. *-adv.* नीचैः, अनुच्चं, नीच in comp.; ' going l ' नीचग; ' l. bending grass ' नीचैः प्रणतानि तृणानि. 2 मंदं, मृदु, सौम्यं. 3 अधस्, अधोभागे, अधस्तात्. *-v. i.* रेभ् 1 A, नद् 1 P, नर्द् 1 P, गर्ज् 1 P, हंभारवं कृ 8 U. **-ing,** *s.* रेभणं, रेभितं, हंभा, हंभारवः. *-s.* हंभारवकारिन्, रेभमाण. **-ness,** *a.* नीचता, निम्नता, अधमता, अपकर्षः, हीनता, अकम्पता, गर्ह्यता, मंद्रता, गांभीर्यं, विषादः, अवसादः, उद्वेगः, दैन्यं, दौर्मनस्यं, म्ला-ग्ला-नि *f.*, &c. **-Lower,** *a.* अवर, अधस्थ, अधस्तन, नीचस्थ, अधःस्थ, अवाच्, अधः in comp.; ' l. world ' अधोलोकः; ' l. garment ' अधोंशुकं; ' l. region ' अधःप्रदेशः; ' the l. classes ' हीन-अधम-जातीयाः, अवरवर्णाः, अंत्यजातीकाः. *-v. t.* न्यूनीकृ 8 U, ऊन् 10, ह्रस् c., अल्पीकृ, लघूकृ, लघयति (D.), अपचि 5 U. 2 अपकृष् 1 P, अव-नम् c. (नमयति), भ्रंश् c., गौरवं-मानं-भंज् 7 P or हृ 1 P; *See* **Humble.** 3 अवतॄ c., अधः कृ, अव-नि-पत् c. *-v. i.* न्यूनीभू 1 P, अल्पीभू, अपचि-क्षि pass., ह्रस् 1 P. 2 नम्रीभू. 3 मलिनीभू, कलुषीभू, तमोवृत-मेघाच्छन्न-*a.* भू. 4 भ्रूभंगं कृ, भ्रुवौ संकुच् 1 P. *-s.* दुर्दिनं, मेघतिमिरं, तिमिरावृतत्वं, साभ्रता. 2 कालुष्यं, मुखमालिन्यं. **-ing,** *a.* तमोवृत, मेघाच्छन्न, साभ्र, दुर्दिनग्रस्त. 2 मलिन, कलुष. **-Lowly,** *a.* नम्र, विनत, सविनय, निरभिमान, अनहंकार, अनुद्धत, अगर्व, नम्रवृत्ति, दर्पहीन; *See* **Humble.** *-adv.* **-ly,** *adv.* सविनयं, विनयेन, नम्रतया, अनुद्धतं. **-ness,** *s.* विनयः, नम्रता, अनहंकारः, अगर्वः, अनभिमानः, नम्रवृत्ति *f.* **-Lowland,** *s.* निम्नदेशः-भूमि *f.*, नीचप्रदेशः, उपत्यका. **-er,** *s.* निम्नदेशीयः.

Loyal, *a.* भक्त, अनुरक्त, दृढभक्ति, भक्तियुक्त-मत्, सानुराग, आसक्त; ' l. to the king ' नृपानुरक्त, प्रभुभक्तिनिष्ठ, राजाज्ञानुवर्तिन्, नृपासक्त; ' a l. wife ' सती, साध्वी, पतिव्रता, एकपत्नी, सुचरित्रा, ' l. husband ' स्वदारनिरतः, भार्यानुरक्तः. **-ly,** *adv.* भक्तिपूर्वं, सानुरागं, दृढभक्तिपूर्वं, राजनिष्ठापूर्वं. **-ty,** *s.* भक्ति *f.*, अनुरागः, आसक्ति *f.*, प्रभु-स्वामिभक्तिः, राजभक्तिः-अनुरागः, दृढभक्तिः, राजनिष्ठा; (in a wife) पातिव्रत्यं, सतीत्वं, &c.

Lubber, *s.* ग्राम्यः, स्थूलजनः, स्थूलधीः-बुद्धिः **-ly,** *a.* स्थूल, अदक्ष. 2 स्थलीय.

Lubric, Lubricious, *a.* स्निग्ध, चिक्कण, श्लक्ष्ण, मेदुर. **-Lubricate,** *v. t.* अभ्यंज् 7 P, स्निग्धीकृ 8 U, स्नेहेन अंज्. **-ed,** *a.* अभ्यक्त, स्नेहाक्त. **-ion,** *s.* अभ्यंजनं, स्निग्धीकरणं. **-Lubricity,** *s.* स्निग्धता, चिक्कणता.

Lucent, *a.* *See* **Bright.**

Lucid, *a.* दीप्तिमत्, शोभन, सुप्रभ, तेजस्विन्, उज्ज्वल, देदीप्यमान; *See* **Bright.** 2 विशद, स्वच्छ, निर्मल, अ-वि-मल, प्रसन्न, शुभ्र. 3 व्यक्त, सुस्पष्ट, भिन्नार्थ, स्पष्टार्थ. 4 प्रसन्नचित्त; ' l. interval ' चित्तप्रसादः. **-ly,** *adv.* स्पष्टं, सुव्यक्तं, भिन्नार्थं; स्फुटं, विशदं. **-ness,** *s.* दीप्ति *f.*, कांति *f.*, शोभा, प्रभा, द्युति *f.*, 2 स्पष्टता, वैशद्यं, प्रसादः, वैमल्यं.

Lucifer, *s.* शुक्रः, भार्गवः; 'l. match' अग्नि-शलाका.

Luciferous, *a.* प्रकाशद, द्युतिकर (री *f.*).

Luciform, *a.* तेजोमय (यी *f.*), प्रकाश-विशिष्ट.

Luck, *s.* दैवं, भाग्यं, भागधेयं, विधिः, नियति *f.*, भवितव्यता, दैवयोगः; *See* **Fate;** 'good l.' सौभाग्यं, पुण्योदयः, भाग्योदयः; 'bad or ill l.' दैवदुर्विपाकः-विपर्ययः-विपर्ययः, मंदभाग्यं, दौर्भाग्यं, दुर्दैवं, दुर्गति *f.*, अशुभं, अमंगलं. **-less,** *a.* भाग्यहीन, मंद-भाग्य, अधन्य, दुर्भाग्य, अभागिन्, भाग्य-दैव-हीन, दुर्दैवग्रस्त, हीनभाग्य. **-lessly,** *adv.* दुर्दैवात्, दुर्भाग्यात्. **-Lucky,** *a.* भाग्यवत्, धन्य, सौभाग्यवत्, पुण्यवत्, भाग्य-दैव-शालिन् 2 शुभ, कल्याण (णी *f.*), भद्र, मंगल, शिव. **-ily,** *adv.* दैवात्, दैवयोगात्, दिष्ट्या, दैव-भाग्य-वशात्, सौभाग्येन. **-iness,** *s.* सौ-भाग्यं, धन्यता, पुण्यवत्ता, &c.

Lucre, *s.* लाभः, आयः, आगमः, फलं, वृद्धि *f.*, अर्थः, फलोदयः, अर्थप्राप्ति *f.* **-Lucrative,** *a.* लाभद, लाभकर (री *f.*), अर्थद, फलावह. **-ly,** *adv.* लाभपूर्व, सफलं.

Lucubrate, *v. i.* रात्रौ अधि-इ 2 A or अभ्यस् 4 U. **-ion,** *s.* रात्र्यध्ययनं, निशा-भ्यासः.

Luculent, *a.* *See* **Lucid.**

Ludicrous, *a.* हास्य, हासकर (री *f.*), उप-अव-हास्य, असंगत. **-ly,** *adv.* असंगतं, हास्यरूपेण.

Lug, *v. t.* बलेन आकृष् 1 P or हृ 1 P.

Luggage, *s.* परिच्छदः, उपस्करः, यात्रासा-मग्री, यात्रापात्रसंभारः.

Lugubrious, *a.* शोकात्मक, दुःखात्मक, कारु-णिक (की *f.*), दुःखावेदिन्.

Lukewarm, *a.* कोष्ण, कवोष्ण, मंदोष्ण, कदुष्ण, ईषदुष्ण, ईषत्तप्त. 2 उत्साहहीन, उदासीन, मंदोत्साह, निरुत्सुक, अतीक्ष्ण, मंदोद्योग, निरुत्साह. **-ly,** *adv.* ईषत्तापेन, कवोष्णं. 2 निरुत्साहं. **-ness,** *s.* कवोष्णता, ईषत्तापः. 2 निरुत्सुकता, मंदोत्साहः, औदा-सीन्यं, मंदोद्योगः, अनौत्सुक्यं.

Lull, *v. i.* शम् 4 P, प्र-उप°, निवृत् 1 A, विरम् 1 P, निर्वा 2 P, विगम् 1 P. **-v. t.** शम् c. (शमयति), सांत्व् 10; निवृत् c. 2 प्र-सद् c., लल् 10; 'l. to sleep' (गीतादिना) स्वप् c. **-s.** शांति *f.*, अक्षोभः, प्र-उप-शमः, निर्वातः, वायुनिवृत्ति *f.*-विरामः-विच्छेदः. **-er,** *s.* शमकः, शांतिदः. **-Lullaby,** *s.* स्वापगीतं.

Lumbago, *s.* कटिवेदना.

Lumber, *s.* भारः, निरर्थकद्रव्यं, निष्प्रयोजन-द्रव्यं. **-v. i.** मंदं चल् 1 P. **-v. t.** संकॄ 6 P. संकुलीकृ 8 U.

Luminary, *s.* ज्योतिस् *n.*, प्रकाशद् *m.*, ज्योतिष्मत् *m.*, तेजस् *n.*; *See* **Star.**

Luminous, *a.* तेजोमय (यी *f.*), सप्रकाश, तेजस्विन्, प्रभावत्, द्युतिमत्, भासुर; 'self-l.' स्वयंप्रकाश. **-ly,** *adv.* तेजसा.

Lump, *s.* राशिः, संघः, चयः, समूहः, ओघः, वृंदं, संचयः, समाहारः; *See* **Multitude.** 2 पिंडः-डं, गंडः, घनः, स्थूलभागः-अंशः. 3 साकल्यं, समासः; 'in the l.' एकीकृत *a.* पिंडित *a.* साकल्येन; 'this is the meaning in the l.' एष पिंडितार्थः (M. I.). **-v. t.** पिंडीकृ 8 U, राशीकृ, पुंजीकृ, एकीकृ, पिंड् 10. **-ish,** *a.* स्थूल; स्थूलबुद्धि. **-y,** *a.* सपिंड, पिंडित, पिंडीभूत.

Lunar, *a.* चांद्र (द्री *f.*), चांद्रमस (सी *f.*), सौम्य, ऐंदव (वी *f.*), gen. ex. by चंद्र-सोम-in comp.; 'l. month' चांद्रमासः; 'l. race' चंद्र-सोम-वंशः; 'l. day' तिथि *m. f.*; 'l. mansion' नक्षत्रं; 'l. eclipse' चंद्रोपरागः.

Lunated, *a.* अर्धचंद्राकार.

Lunatic, *a.* उन्मत्त, सोन्माद, वातुल, भ्रांत-चित्त-मति-बुद्धि, विक्षिप्तचित्त, हत-नष्ट-बुद्धि; 'a l. asylum' वातुलालयः. **-Lunacy,** *s.* उन्मादः, बुद्धि-मति-भ्रंशः, चित्तविक्षेपः-विप्लवः, वातुलता, मति-बुद्धि-भ्रमः.

Lunch, Luncheon, *s.* उपहारः, लघ्वाहारः.

Lune, *s.* अर्धचंद्राकृतिः.

Lungs, *s.* तिलकं, क्लोमन् *n.*, क्लोमं, फुप्फुसः-सं.

Luniform, *a.* चंद्राकृति, चंद्राकार.

Lupine, *s.* द्विदलं, शमीधान्यं. **-a.** वृकसंब-न्धिन्, वृकसदृश.

Lurch, *v. i.* अप-सृ 1 P, निभृतं स्था 1 P, नि-ली 4 A. 2 **Disappoint, Steal,** q. v. **-er,** *s.* कौटिकः. 2 कौटिककुक्कुरः.

Lure, *v. t.* प्र-वि-लुभ् c., आकृष् 1 P, हृ 1 P, प्र-वृत् c., प्रोत्सह् c., प्रलुभ् 6P or c., मुह् c., प्रलुभ् 10. 2 आमिषदर्शनेन आकृष्. **-s.** प्र, विलोभनं, आकर्षणं, प्रोत्साहनं. 2 आमिषं, आमिषदर्शनं.

Lurid, *a.* वि-,पांडु, मलिन, उग्रदर्शन, घोर-रूप, मलिनप्रभ, तमोवृत.

Lurk, *v. i.* निभृते-प्रच्छन्नं-स्था 1 P or वृत् 1 A, नि-ली 4 A, गुप् pass.; *See* **Conceal.** **-er,** *s.* निभृतस्थायिन् *m.* **-ing,** *s.* प्रच्छ-न्नवासः, गुप्ति *f.*, 'l.-place' निलयः, गुप्तिः, निभृत-गूढ-स्थानं.

Luscious, *a.* ललित, सुभग, अतिमधुर, कमनीय, सुस्वादु, सुमधुर, अतिमिष्ट-स्वादु. **-ly,** *adv.* अतिमधुरं, सुस्वादु. **-ness,** *s.* अतिमाधुर्यं, सुस्वादुता.

Lush, *a.* सरस, रसगर्भ.

Lust, *s.* कामः, कामानलः, मैथुनेच्छा, सुरता-र्थिता, मदनः, व्यवायेच्छा, रताभिलाषः,

विषयसुखेच्छा, इंद्रियासक्ति *f.* 2 अतिस्पृहा-वांच्छा, लालसा, अतिलिप्सा, लोभः, वांछा, आकांक्षा, अभिलाषः. 3 दुर्वासना, कुवासना. —*v. i.* मैथुनं-सुरतं इष् 6 P or अभिलष् 1, 4 P, रतार्थिन्-*a.* भू; better ex. by 'l.-ful.' 2 अत्यंतं इष् or वांछ् 1 P or स्पृह् 10 or कांक्ष् 1 P, लुभ् 4 P, लुभ् 4 P. **-ful,** *a.* कामासक्त, कामांध, कामुक, कामिन्, इंद्रियवश विषयानिरत, इंद्रियसुखासक्त, कामार्त, कामातुर, कामग्रस्त, कामजित, कामाविष्ट, स्मरातुर, कामवृत्ति, रतार्थिन्, मैथुनार्थिन्, मैथुनेच्छु, व्यवायिन्, लंपट, स्त्रीलंपट-पर-व्यसनिन्, कामन, अभीक, अनुक. **-fully,** *adv.* सकामं, कामुक-लंपट-वत्.

Lusty, *a.* महाबल, सवीर्य, ससत्त्व, सबल, बल-वीर्य-वत्, मांसल, दृढांग (गी *f.*), दृढशरीर, वज्रदेह, पृथुशरीर, व्यूढोरस्क, अंसल, महाकाय. **-ly,** *adv.* सवीर्यं, ससत्त्वं, बलवत्, तेजसा, पौरुषेण. **-ness,** *s.* वीर्यं, सत्त्वं, मांसलता, दृढांगता, &c.

Lustral, *a.* पावन, पावक, शुद्धिकर (री *f.*); 'l. water' पावनोदकं, शांत्युदकं. **-Lustrate,** *v. t.* पू 9 U, शुध् c. **-ion,** *s.* शुद्धि *f.*, शोधनं, पावनं, पवित्रीकरणं.

Lustre, *s.* द्युतिः, कांतिः, दीप्तिः, रुचिः, भास्, रुच्, शोभा, प्रभा, ओजस्विता (all *f.*), तेजस् *n.*, प्रकाशः, प्रतापः, उद्द्योतः. **-Lustrous,** *a.* सुप्रभ, उज्ज्वल, तेजस्विन्, शोभन, दीप्ति-कांति-मत्; *See* **Bright.**

Lustrum, *s.* वर्षपंचकं.

Lutarious, *a.* पंकस्थ, कर्दमवासिन्. 2 पंकिल, कार्दम (मी *f.*). 3 पंकवर्ण.

Lute, *s.* वीणा, वल्लकी, विपंची-चिका, तंत्रीः, परिवादिनी (seven-stringed); 'bow of a l.' कोणः, शारिकः, रणः; 'play on a l.' वीणां वद् c. **-Lutanist, Luter, Lutist.** *s.* वीणावादः-दकः, वैणिकः.

Luteous, Lutescent, *a.* पीतवर्ण.

Luxate, *v. t.* विसं-धा 3 U, अस्थिग्रंथिं भंज् 7 P or त्रुट् c. or विसं-धा. **-ed,** *a.* संधिच्युत-भ्रष्ट, संधि-विश्लिष्ट, त्रुटितसंधि. **-ion,** *s.* अस्थित्रोटनं-भंगः-विश्लेषः.

Luxury, *s.* विषयसुखं, सुखोपभोगः, सुखभोग-आसक्ति *f.*, विषयभोगः-सेवा, विलासः, विलासित्वं, सुखसेवा-आस्वादः. 2 सुखं, भोगः, सुखसाधनं, भोगसाधनं, सुखसाहित्यं. 3 स्वाद्वन्नं, भोजनविशेषः, उत्तमान्नं, विशिष्टभोजनं. **-iance,-iancy,** *s.* अति-वृद्धि-स्फीति *f.*, समृद्धि *f.*, वृद्धिबाहुल्यं, उद्रेकः. **-iant,** *a.* अतिवर्धिष्णु, अतिस्फीत, अति समृद्ध, सुमधुर, अत्यंत, अतिबहुल, उद्रिक्त, अतिरिक्त, अत्यधिक. **-iantly,** *adv.* अतिसमृद्ध्या, अतिमात्रेण, बाहुल्येन, अतिबहुलं, अतिरिक्तं, अतिबहुशः. **-iate,** *v. i.* अत्यंतं वृध् or स्फाय् 1 A or पुष् 4, 5 P or आ-प्यै 1 A, अतिवृद्धिं इ 1 P, अतिमेदुरीभू 1 P. 2 अतिविलासेन वृत् 1 A or अव-स्था 1 A यथेच्छं सेव् 1 A or उपभुज् 7 A. **-ious,** *a.* विलासासक्त, विषयसेविन्, विषयासक्त, सुख-भोग-परायण, इंद्रियसुखनिरत, सुखास्वादतत्पर. 2 विलासयुक्त-मय (यी *f.*), सविलास, अतिसुखावह, सुखभोगकर (री *f.*), भोगाकुल. **-iously,** *adv.* सविलासं, अतिसुखेन; सुखोपभोगपूर्वं, सुखासक्तवत्. **-iousness,** *s.* विलासित्वं &c.; *See* (*s.*).

Lye, *s.* क्षारोदकं, क्षारजलं.

Lymph, *s.* वसा, मेदस् *n.* 2 निर्झरः, उत्सः, वाहः. **-Lymphatic,** *s.* मेदोवाहिनी.

Lynx, वनमार्जारः-बिडालः.

Lyre, *s.* वीणा, विपंची; *See* **Lute.** **-ic, -ical,** *a.* वैणिक (की *f.*). **-ist,** *s.* वैणिकः.

Lythrum, *s.* अग्निज्वाला, सुभिक्षा, धातकी, धातु(तु)पुष्पिका.

M.

Macaw, *s.* चक्रतुंडः, शुकः, कीरः.

Mace, *s.* जातिपत्री, जाति-ती *f.*, जाति(ती)कोशं, जातिफलं-कोशं. 2 गदा; दंडः, यष्टि *m. f.*; वेत्रं, लगुडः, मुस(श)लः-लं, मुद्गरः; 'm.-bearer' दंड-यष्टि-धरः, वेत्रधरः, गदाहस्तः पाणिः, यष्टिग्रहः, वेत्रपाणिः, दंडभृत्.

Macerate, *v. t.* जलेन आप्लु c., आर्द्रीकृ, 8 U, सं-धा 3 U. **-ion,** *s.* संधानं, पाचनं आर्द्रीकरणं.

Machinate, *v. t.* मंत्र् 10 A, (उपायं) चिंत् 10, संप्र-धृ 10, परिकल्पय् c., गुप् 10. 2 द्रुह् 4 P, कपटप्रबंधं रच् 10, गूढमंत्रणां कृ 8 U. **-ion,** *s.* कुकल्पना, कुमंत्रणा, कूटप्रबंधः, गूढप्रयोगः, कपटप्रबंधः, द्रोहचिंतनं, कल्पना, चिंतनं, योजना, विधानं. **-or,** *s.* कुमंत्रणाकृत् *m.*, कपटप्रबंधरचकः.

Machine, *s.* यंत्रं, साधनं, उपकरणं. **-Machinery,** *s.* यंत्राणि, यंत्रसामग्री, यंत्रसमुदायः. **-Machinist,** *s.* यंत्रकारः-विद्, यंत्रकलाज्ञः. **-Mechanic,** *s.* शिल्पिन् *m.*, शिल्पकारः, कर्मकारः, कारुः, शिल्पोपजीविन् *m.*—*a.* **-al,** —*a.* यंत्र in comp., यंत्रसंबंधिन्, यंत्रविषय, यंत्र-शिल्प-विद्यासंबंधिन्, यांत्रिक (का *f.*). 2 शिल्पविद्याकृत, यंत्रकार्यानुरूप; 'm. art' शिल्पं, कला. 3 यंत्रतुल्य, यंत्र-

वत्, अप्रबोधपुरःसरं. 4 यंत्रविद्या-शिल्पविद्या-निपुण, शिल्पकारिन्. **-ally,** *adv.* यंत्रविद्यानुरूपं, शिल्पशास्त्रानुसारेण. 2 यंत्रवत्, अबुद्धिपूर्वं, अमति-अप्रबोध-पूर्वं. **-ian,** *s.* शिल्पशास्त्रज्ञः, यंत्रविद्याकुशलः. **-Mechanics,** *s.* यंत्र-शिल्प-विद्या-शास्त्रं, यंत्रगतिशास्त्रं. **-Mechanism,** *s.* यंत्ररचना, कला, युक्ति *f.*; यंत्रगति *f,* यंत्रव्यापारः. **-Mechanist,** *s.* यंत्रकारः.

Macrocosm, *s.* विश्वं, त्रिभुवनं, अखिलं जगत्.

Macrology, *s.* अतिविस्तारः, दीर्घसूत्रता.

Macula, *s.* कलंकः, अंकः, लांछनं, लक्ष्मन् *n.* **-Maculate,** *v. t.* कलंकयति-मलिनयति (D.), **-a.,-ed,** *a.* कलंकित, कलुषित, लांछित.

Mad, *a.* उन्मत्त, वातुल, सोन्माद, हत-नष्ट-भ्रष्ट-बुद्धि, हतज्ञान, भ्रांत-विक्षिप्त-चित्त; 'make m.' उन्मादं नी 1 P, उन्मद् c.; 'to go m.' उन्मद् 4 P. 2 (Of acts) बालिश, उन्माद-युक्त, असमीक्ष्यकृत, साहसिक (की *f.*); 'm.-brain,-brained' विक्षिप्तबुद्धि &c.; 'm.-cap' साहसिकः; 'm. with anger' संरब्ध, कोपाकुल, मन्दोदग्र; 'm.-house' वातुलालयः; 'a m. dog' अलर्कः; 'a. m.-man' वातुलः, उन्मत्तः. **-den,** *v. t.* उन्मद् c., वातुलीकृ 8 U, व्यामुह् c., उन्मत्तीकृ; 'm. ed with rage' क्रोधांध; 'm. ed with liquor' सुरापानमत्त. **-ing,** *a.* उन्मादक, उन्मादजनन (नी *f.*). **-ly,** *adv.* उन्मत्तवत्, उन्मादात्, सोन्मादं, वातुलवत्, चित्तविभ्रमेण, भ्रांतचेतसा. 2 साहसिकतया. **-ness,** *s.* उन्मादः, उन्मत्तता, वातुलता, मति-बुद्धि-भ्रमः, चित्तविप्लवः-विक्षेपः, मति-बुद्धि-भ्रंशः. 2 (Fig.) व्यामोहः, मूढता, साहसं.

Madam, *s.* आर्या, भाविनी, कुलजा; (in addresing) आर्ये, भवति.

Madder, *s.* मंजिष्ठा, विकसा-षा, जिंगी, समंगा, कालमेषि(षि)का, मंडूकपर्णी, मंडि-(डी)री, भंडी, योजनवल्ली.

Madefy, *v. t.* क्लिद् c., आर्द्रीकृ 8 U.

Magazine, *s.* नानाविषयसंबद्धं पुस्तकं; 'a m. of arms' आयुधागारं, शस्त्रागारं. 2 भांडागारं.

Maggot, *s.* कृमिः, कीटः. **-y,** *a.* कीटमय (यी *f.*), कीटपूर्ण.

Magic, *s.* इंद्रजालं, माया, अभिचारः, मंत्रयोगः, वशक्रिया, कुहका-कं, मंत्रः, कार्मणं, कुसृति *f.*, मोहः, योगः. **-a.,-al,** *a.* ऐंद्रजालिक-आभिचारिक-मायिक-कौसृतिक-(की *f.*), मायामय (यी *f.*), मोहिन्, माया in comp. **-ally,** *adv.* इंद्रजालेन, मायया, अभिचारेण. **-ian,** *s.* ऐं(इं)द्रजालिकः, मायाविन् *m.*, मायाकारः, मायिन् *m.* अभिचारिन् *m.* कुहकः, कुहकाजीविन् *m.* कौसृतिकः, योगिन् *m.*, योगेश्वरः, सिद्धः; 'm.'s brush' पिच्छिका.

Magistrate, *s.* धर्माध्यक्षः, न्यायाध्यक्षः; *See* **Judge. -Magistracy,** *s.* धर्माधिपत्यं, न्यायाधिकरणं, धर्माधिकारः. 2 धर्माध्यक्ष-गणः-समूहः. **-Magisterial,** *a.* (*s.*) in comp., आधिकारिक (की *f.*). 2 प्रभुत्व-विशिष्ट, आज्ञापक, सावलेप, धृष्ट, प्रगल्भ. **-ly,** *adv.* शासनरूपेण; सदर्पं, सावलेपं.

Magnanimous, *a.* महात्मन्, महामनस्, महामनस्क, महानुभाव, उदार-धी-चेतस्-मति, उदार, महेच्छ, महाशय, उदारात्मन्. 2 (Of acts) अवदात, उदार, औदार्यपूर्ण. **-ly,** *adv.* औदार्येण, माहात्म्येन, महानुभावात्, उदारचेतसा. **-Magnanimity,** *s.* माहात्म्यं, उदारात्मता, महात्मता, औदार्यं, महानुभावः, चित्तौदार्यं, उदारमतिता, महेच्छा, महाशयः.

Magnate, *s.* उत्कृष्टपदस्थः, उच्चपदस्थः, धुरंधरः, धुरीणः.

Magnet, *s.* अयस्कांतः, अयोमणिः, लोहकांतः, चुंबकः. **-ic, -ical,** *a.* आकर्षक, आकर्षणशील, लोहचुंबनशील; 'm. needle' अयस्कांतशलाका; 'm. attraction' आकर्षः-र्षणं. **-ically,** *adv.* आकर्षणद्वारेण. **-ism,** *s.* अयस्कांतगुणः, आकर्षणशक्ति *f.*, लोहकांतधर्मः. **-ize,** *v. t.* आकर्षणशक्तिं दा 3 U or संक्रम् c. or संचर् c.

Magnificent, Magnific, *a.* शोभमान, तेजस्विन्, अतिशोभन, महाप्रभ, श्रीमत्, महातेजस्, महाप्रताप, विभूतिमत्, देदीप्यमान. 2 (Palace &c.) विशाल, तुंग, उज्ज्वल. **-ly,** *adv.* अतितेजसा, सप्रतापं, विभूत्या, ऐश्वर्येण. **-Magnificence,** *s.* महिमन् *m.*, प्रतापः, श्रीः, शोभा, तेजस् *n.*, अतिप्रतापः शोभा-प्रभा, ओजस्विता, महाप्रतापः, विभूति *f.*, औज्ज्वल्यं, विभवः, ऐश्वर्यं.

Magniloquent, *a.* प्रौढ-प्रगल्भ-वाच्, धृष्ट-वाच्. **-Magniloquence,** *s.* प्रौढभाषणं, प्रगल्भोक्ति *f.*, गर्वोक्तिः.

Magnify, *v. t.* वृध् c., उप-चि 5 U, स्फाय् c. (स्फावयति), अधिकीकृ 8 U; *See* **Increase.** 2 अत्यंतं वर्ण् 10, उत्-सं-कृत् 10. 3 अतिशयोपमया वृध् c. or विस्तृ c. **-er,** *s.* वर्धकः. 2 बृंहणयंत्रं. **-ing,** *a.* वर्धिन्, बृंहणकारिन्.

Magnitude, *s.* मानं, प्र-परि-माणं, आकारमानं, मात्रा in comp., इयत्ता; 'of the m. of an egg' अंडमात्र, अंडपरिमाण. 2 गुरुत्वं, महत्त्वं, बृहत्त्वं, वैपुल्यं, प्रथिमन् *m.*, गरिमन् *m.*, महिमन् *m.*, पृथुता, विशालता.

Mag-pie, *s. See* **Jay.**

Maid, Maiden, *s.* कन्या, कुमारी, तरुणी, बालिका, युवतिः-ती, बाला, कन्यका, कुमारिका. 2 अनूढा, अपरिणीता, अविवाहिता, अदत्ता, अक्षत-अविद्ध-योनिः. 3 (M.-servant) दासी, चेटी, प्रेष्या, परिचारिका,

कर्मकरी. **-a.** कौमार (री *f.*), कन्याविषय. 2 अभिनव, अकृतोपभोग, अक्षत, अखंड. **-hood,** *s.* कौमारं, तारुण्यं, कुमारीभावः-दशा. 2 अभिनवत्वं, अखंडता. **-ly, -like,** *a.* कन्यकोचित, कन्या-कुमारी-योग्य.

Mail, *s.* वर्मन् *n.*, तनुत्रं, तनुत्राणं, कवचः-चं, उरश्छदः, दंशनं, कंकटकः, ज(जा)गरः; *See* **Armour;** 'm.-coat' कंचुकः, वारबाणः; 'having put on a m.-coat' आ-प्रति-मुक्त, अपिनद्ध, पिनद्ध. 2 पत्र-लेख्य-वाहनं. **-ed,** *a.* सकवच, कवचिन्, कवच-धारिन्; कृतसन्नाह, वर्मित, सन्नद्ध, सज्ज, दंशित, व्यूढकंकट.

Maim, *v. t.* विकली-व्यंगी-कृ 8 U, हीनांगीकृ, विकलयति (D.). **-s** अंगवैकल्यं, हीनांगता, न्यूनावयवत्वं. **-ed,** *a.* विकलांग (गी *f.*), व्यंग, हीनांग, विकल, अंगविकल.

Main, *a.* मुख्य, प्रधान, प्रमुख, परम, अग्र्य, श्रेष्ठ, उत्कृष्ट, उत्तम, विशिष्ट, मूल in comp., मुख्यतम; 'm. matter' गुरुकार्यं, गुर्वर्थः; 'm. door' सिंहद्वारं; 'm. stock' मूलधनं. **-s.** प्रधानभागः, प्रधानांशः, मुख्यांशः, बाहुल्यं, भूयिष्ठभागः. 2 महोदधिः, महार्णवः; *See* **Sea** 3 बलं, शक्ति *f.*, प्रभावः, सामर्थ्यं. 4 प्राणि-पतनं, समाह्वयः; 'in the m.' बहुशः, बाहुल्येन, भूयिष्ठं, सामान्यतः; 'with might and m.' सर्वबलेन, प्रसभं, प्रसह्य; 'm. land' मध्य-मूल-भूमि *f.*, मुख्य-प्रधान द्वीपः-पं. **-ly,** *adv.* मुख्यशः, बहुशः, प्रधानतः, मुख्यांशेन, भूयिष्ठं, बहुतरं, सामान्यतः, विशेषेण, प्राधान्येन.

Maintain, *v. t.* ग्रह् 9 U, धृ 1 P, 10. 2 पा c. (पालयति), रक्ष् 1 P, भृ 1 P, 3 U आ-अव-लंब् 1 A, उत्तभ् 9 P or c., संस्तंभ् संवृध् c., पुष् 1, 9 P or c., योगक्षेमं वह् 1 P, पालनं-पोषणं कृ 8 U. 3 प्रवृत् c., रक्ष् न विच्छिद् 7 P or वि-रम् 1 P. 4 प्रति-पद् c., वद् 1 P, निर्वह् 1 P or c., समर्थ् 10, संस्तंभ्, दृढीकृ, अनु-पा c. (पालयति); *See* **Fulfil** also. 5 (As a theory) वद् 1 P, 'he who m. s that there is God' ईश्वर-वादिन्; 'one who m. s the doctrine of atheism' नास्तिकमतवादिन्. 6 सनिश्चयं वद् 1 P, दृढीकृत्य प्रति-पद् c.; 'to m. oneself' जीवितं धृ, शरीरवृत्तिं कृ or निर्वृत् c.; *See* **Live** (on). **-er,** *s.* पालकः, पोषकः, रक्षितृ *m.*, आलंबिन्, भरः-धरः- in comp. **-Maintenance,** *s.* धारणं. 2 रक्षा, रक्षणं, भरणं, भृति *f.*, आ-समा-लंबनं, पालनं, पोषणं, संवर्धनं 3 जीविका, वृत्ति *f.*, आ-उप-जीविका, आजीवः, प्राणधारणं; *See* **Living.** 4 प्रमाणीकरणं, अनुच्छेदः, अनाच्छादनं. 2 प्रतिपादनं, निर्वाहः.

Maize, *s.* [illegible]

Majesty, *s.* राजश्रीः, राजप्रतापः-तेजस् *n.*, राजमहिमन् *m.*-प्रभावः-गौरवं, प्रतापः, राजत्वं, तेजः, प्रभावः, ऐश्वर्यं, महिमन् *m.*, वैभवं, विभूति *f.*, गौरवं, महत्त्वं; 'your m.' देवः, महाराजः, देवपादाः, स्वामिन् *m.*, श्रीमद्देवपादाः, प्रभुः, प्रभविष्णुः; (in addressing) देव, महाराज, &c. **-ic, -ical,** *a.* राजयोग्य, राजतुल्य, नृपोचित, राजतेजोमय (यी *f.*), राजश्रीमत्, राजप्रतापवत्, सानुभाव, सावष्टंभ, प्रतापवत्, ऐश्वर (री *f.*), विभूतिमत्, प्रभाववत्, ओजस्विन्; उन्नत, अतिप्रौढ, उज्ज्वल, उत्तुंग; *See* **Lofty** also; 'm. splendour' द्युति *f.*; 'm. dignity' अनुभावः, अवष्टंभः, ओजस्विता. **-ically,** *adv.* राजसदृशं, सावष्टंभं, सानुभावं, नृपोचितं, राजप्रतापेन-तेजसा-महिम्ना, सप्रतापं, सप्रभावं, ऐश्वर्येण, सगौरवं.

Major, *a.* अधिक, भूयस्, अधिकसंख्य. 2 मुख्य, प्रधान, प्रमुख, गुरु, वरीयस्, वर्षीयस्. **-s.** प्राप्तव्यवहारः, व्यवहारक्षमः-योग्यः, अतीत-त्यक्त-शैशवः. 2 गुल्माध्यक्षः, सैन्यदलाध्यक्षः. **-Majority,** *s.* बहु (pl.), बहुतरभागः, भूयिष्ठभागः, अधिकसंख्या; 'a m. of members have come' सभासदां मध्याद्बहवः समागताः; 'm. of votes' बहुमतं, मताधिक्यं. 2 व्यवहारः, व्यवहारक्षमता, व्यवहार्यदशा, वयस् *n.*; 'reached his m.' प्राप्तव्यवहारः, त्यक्तशैशवः; *See* **Grow up.**

Make, *v. t.* कृ 8 U, वि-धा 3 U, अनु-ष्ठा 1 P, आचर् 1 P. 2 (Create) निर्मा 3 A, 2 P, सृज् 6 P, घट् c., (घटयति), कृ, वि-धा, रच् 10, कॢप् c., उत्पद् c., जन् c. (जनयति), साध् c., निः-सं-पद् c. 3 (Produce) उत्पद् c., जन् c., कृ; *See* **Cause.** 4 (Force) ex. by causal of roots; 'm. s me question you' प्रश्नकर्मणि मां नियोजयति (Ka. 134); *See* **Compel.** 5 निर्मा, घट् c.; gen. ex. by निर्मित, घटित, रूप, मय, आत्मक in comp.; also by भू 1 P, सं-पद् 4 A; '10 repeated 2 times m s 20' द्विरावृत्ता दश विंशतिर्भवति or संपद्यते. 6 आप् 5 P, विद् 6 U, लभ् 1 A; *See* **Get;** 'm. amends for' क्षतिं पूर् 10, प्रतिफलं दा 3 U, प्रमृज् 2 P, निष्कृ; 'm. account of' मन् 4 A or c., गण् 10, अपेक्ष् 1 A; 'to m. the best of a bad matter' दोषमपि गुणत्वमापादयितुं; 'self-made man' स्वोद्यमलब्धप्रतिष्ठः; 'm. merry' हृष्ट-*a.* भू, उत्सवं कृ; 'm. much of' बहु मन्; 'm. light of' तृणाय मन् or गण्, लघूकृ, अव-ज्ञा 9 U; *See* **Contemn;** 'm. way' अंतरं दा; अप-सृ 1 P, अप-इ-या 2 P; अपक्रम् 1 U, 4 P; 'm. free with' संकोचं त्यक्त्वा आचर् or व्यवहृ 1 P, 'm. away with' नश् c., व्या-पद् c., हन् 2 P or c.

(घातयति); *See* **Kill;** '**m. water**' मूत्रोत्सर्गं कृ; 'm. good' पा c.(पालयति), पूर् 10, तॄ 1 P, रक्ष् 1 P (promise &c.); *See* **Fulfil** also; सं-पद् c., साध् 5 P or c. (loss) पूर्, प्रतिविधा 3 U, सतीकृ, अपाकृ, क्षुध् c.; 'm. bold to say' प्रगल्भतया वद् 1 P or वचनसाहसं कृ **-for,** अभि-या 2 P, प्रति-या, उपसृप्-उपगम् 1 P, अभि-उप-सृ 1 P. **2** आरुह् 1 P कॢप् 1 A. **-into,** निर्मा, वि-धा; 'gold is made into ornaments' सुवर्णस्यालंकाराः क्रियंते. **-of,** *See* **Make** (5) above; 'made of' मय (यी *f.*), घटित, निर्मित, आत्मक, रूप in comp., or only by comp.; 'a pot made of gold' हेमनिर्मितं पात्रं, हेमपात्रं. **2** अवगम् 1 P; बुध् 1 P; 'not knowing what to m. of it' किं नु एतत्स्यादिति ज्ञातुमसमर्थः. **-off,** पलाय् 1 A, अपक्रम्, अप-इ, अप-सृ-गम्-धाव् 1 P. **-out,** निरूप् 10, ज्ञा 9 U, अवगम्, ग्रह् 9 U, उपलभ् 1 A, विद् 2 P; *See* **Know. 2** प्रति-पद् c., समर्थ् 10; प्रमाणीकृ, साध् c., निष्पद् c. **-over,** सम्-ऋ c. (अर्पयति), संक्रम् c., निक्षिप् 6 P, न्यस् 4 U, आयत्तीकृ. **-up,** समाहृ 1 P संकल् 10, संभृ 1 P, 3 U, समा-नी 1 P, एकीकृ. **2**(A loss) पूर्, प्रतिवि-धा; 'you should m. up for your want of beauty by being good' त्वया अलावण्यदोषः सदाचरणेन प्रतिविधेयः. **3** (A quarrel) सं-धा, प्रशम् c., (प्रशमयति विवादं S. 5). **4** निर्णी, साध्, निष्पद् c.; 'm. up one's mind' निर्णी, निश्चि 5 U; *See* **Determine;** 'm. up to' उपसृ, उपगम्; *See* **Approach.** **-s.** आकारः, आकृति *f.*, रूपं, विग्रहः, अंगं, वपुस् *n.*; 'handsomeness of m.' अंग-सौष्ठवं. **-er,** *s.* कारः, करः, कारिन्, कृत् in comp.; कर्तृ *m.*, निर्मातृ *m.* विधातृ *m.*, कल्पकः, रचकः, घटकः; 'm. of pots' कुंभकारः-कृत् &c. **2 Creator,** q. v. 'man is the m. of his own fortune' लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयंति (H. 2). **-ing,** *s.* करणं, विधानं, रचनं, कल्पनं, निर्माणं, &c.

Maladdress, *s.* अपटुत्वं, अकौशलं.

Maladministration, *s.* कुशासनं, दुर्णयः, असम्यक् निर्वाहः.

Maladroit, *a.* अपटु, अकुशल.

Malady, *s.* रोगः, व्याधिः, आमयः, विकारः, रुजा, गदः; *See* **Disease.**

Mala fides, *adv.* सव्यलीकं. **-s.** विप्रलिप्सा, वंचनेच्छा.

Malaise, *s.* व्यग्रता, आकुलता, उद्विग्नता.

Malapert, *a.* अविनीत, धृष्ट, प्रगल्भ, प्रतिभानवत्, निर्लज्ज. **-ly,** *adv.* अविनयेन, धृष्टवत्, निर्लज्जं. **-ness,** *s.* अविनयः, धृष्टता, प्रागल्भ्यं, प्रतिभा-भानं.

Malapropos, *adv.* अस्थाने, अकाले, अनवसरे.

Malaria, *s.* पूतिवायुः, दुर्वातः.

Malcontent, *a.* or *s.* असंतुष्ट, अप-वि-रक्त, राजापरक्त, राजनीत्यसंतुष्ट.

Male, *s.* पुंस् *m.*, पुरुषः, नरः, नृ *m.*; 'm. and female' स्त्रीपुंसौ, स्त्रीपुरुषौ, युग्मं, मिथुनं, द्वंद्वं. **-a.** ex. by masc. gender; पुंजातीय; 'm. sparrow' चटकः; sometimes by पुरुष-पुं-नर- in comp., 'm. tiger' पुंव्याघ्रः; 'm. cuckoo' पुंस्कोकिलः; 'm. attire' पुरुषवेशः; 'm. child' अपत्यं पुमान्, पुत्रः, सुतः, &c.; 'm. species' पुंजाति *f.*, पुरुषजातिः.

Malediction, *s.* शापः, आक्रोशः-शनं. **-Maledictory,** *a.* अभिशापक, आक्रोशगर्भ, अमंगलाशंसिन्.

Malefactor, *s.* पातकिन् *m.*, पापिन् *m.*, अपकारिन् *m.*, अपराधिन् *m.* पापकर्मन् *m.*, दुष्कृतिन् *m.* दोषभाक्, कृतागस् *m.*

Malefic, *a.* अपकारिन्.

Malevolent, *a.* अभिद्रुग्ध, द्रोहमति-बुद्धि, दुष्ट-भाव-मति-बुद्धि, दुरात्मन्, दुराशय, कुबुद्धि दुर्बुद्धि, मत्सरिन्, साभ्यसूय, पापाशय, अहितैषिन्, दुर्हृद्, दुःशील, अनिष्टार्थिन्. **-ly,** *adv.* द्रोहबुद्ध्या, दुष्टभावेन, साभ्यसूयं, अहितेच्छया. **-Malevolence,** *s.* द्रोह-अहित-बुद्धि *f.*, दुष्टभावः, कुभावः, कुबुद्धिः, द्रोहमति *f.*, द्रोहः, असूया, अभ्यसूया, दौरात्म्यं, मात्सर्यं, अहितेच्छा, अपकारेच्छा, पैशुन्यं.

Malfeasance, *s.* अपकारः, दुष्कर्मन् *n.*

Malformation, *s.* विकृति *f.* वैरूप्यं.

Malice, *s.* वि-,द्वेषः, वैरं, द्वेष-शत्रु-भावः, द्रोहः, दुष्टभावः, द्रोहमति-बुद्धि *f.*, मात्सर्यं, असूया, अहितेच्छा, पापाशयः, दौरात्म्यं, दौर्जन्यं, पैशुन्यं. **-Malicious,** *a.* वैर-द्वेष-पूर्वक, द्रोह or द्वेष-मूल or हेतुक. **2** अतिद्वेषिन्, द्रोहिन्, द्रोहमति-बुद्धि, दुष्टभाव-मति, द्रोहशील, अपकारेच्छु, पापात्मन्, दुरात्मन्, साभ्यसूय, मत्सरिन्, दुर्जन, खल, पिशुन; *See* **Malevolent. -ly,** *adv.* द्रोहबुद्ध्या, दौरात्म्येन, सद्वेषं, मात्सर्येण; 'm. intentioned' द्रोहबुद्धि &c. **-ness,** द्रोहमतित्वं, दुष्टशीलता; *See* (*s.*)

Malign, *v. t.* अपभाष् 1 A, परि-अप-वद् 1 U, अभिशंस् 1 P, कलंकयति (D.), वि-,द्विष् 2 U. **-a., -ant,** *a.* द्वेषबुद्धि, द्रोहपरायण, दुष्टबुद्धि, दुर्बुद्धि, दुराशय, नृशंस, दुर्मति; *See* **Malicious, Malevolent. 2** (Star) अशुभ, दुष्ट, अनिष्ट, अमंगल. **3** उग्र, घोर, अतिदुष्ट, अरुंतुद, अतितिग्म. **4** असाध्य, दुःसाध्य, दुश्चिकित्स्य, मारात्मक, सान्निपातिक (की *f.*), काल in comp. **-ly, -antly,** *adv.* सद्रोहं, अरुंतुदं. **-er,** *s.* अभिशंसकः, अपवादकः, पिशुनः. **-ity, -Malignancy,** *s.* द्रोहबुद्धि *f.*, द्वेषपरायणता, परमद्वेषः, भावदुष्टता, अतिपैशुन्यं;

See **Malice. 2** उग्रता, तिग्मता, क्रूरता, 3 असाध्यता, मारात्मकता.
Malinger, *v. i.* शरीरास्वास्थ्यं अपदिश् 6 P.
Malison, *s. See* **Curse.**
Malkin, *s.* अशुद्धा, भ्रष्टा.
Mall, *s.* महामुद्गरः, घनः. **2** जनाकीर्णमार्गः, जनसामान्यपथः.
Malleable, *a.* उद्वर्तनीय, घनेन वर्धनीय, उद्वर्तनक्षम. **-Malleate,** *v. t.* मुद्गराघातेन उद्-वृत् c.
Mallet. मुद्गरः, द्रुघणः, घनः
Malodorous, *a.* दुर्गंधि.
Malpractice, *s.* दुराचारः, दुश्चरितं, कुचरितं, कुचेष्टितं.
Malt, *s.* यवपानीयबीजं; 'm.-drink' यवसुरा, यवजं, यवपानीयं; 'm.-house' यवसंधानगृहं.
Maltreat, *v. t* अप्रियं आचर् 1 P or वृत् 1 A. नि-अप-विप्र-कृ 8 U, पीड् 10. **-ment,** *s.* अपकारः, निकारः, पीडा.
Malversation, *s.* दुराचरित, शाठ्यं, धूर्तता; *See* **Fraud.**
Mamma, *s.* माता, अंबा, जननी; *See* **Mother.**
Mammal, *s.* सस्तन *a.* प्राणिन्. **-ia,** *s.* सस्तनाः प्राणिनः
Mammiferous, *a.* सस्तन, स्तनविशिष्ट.
Mammiform, *a.* स्तनाकृति, कुचाकार.
Mammon. *s.* धनं, लक्ष्मीः, संपद् *f.* (the god) कुबेरः. **-ist,** *a.* or *s.* धनपरायण, द्रव्यार्जनतत्पर. **-ism,** *s.* द्रव्यपरायणता.
Man, *s.* मनुष्यः, मानुषः, मनुजः, नरः, नृ *m.*, मानवः, पु(पू)रुषः, मर्त्यः, पुंस् *m.* **2** (As opposed to child) मानुषः, प्रौढवयस्कः, त्यक्तशैशवः, मानुष्यप्राप्तः, प्रौढः. **3** (As opposed to woman) पुरुषः, पुमान्, नरः. **4** (M.-kind) मनुष्याः, मानवाः, मनुष्यजाति *f.*, मर्त्याः, मानुष्यं, मानुषता, जनः, लोकः, मनुष्यजीव-लोकः. **5** (In chess) शा(सा)रः-रिः; 'an eminent m.' पुरुषसिंहः-व्याघ्रः, नरवरः-शार्दूलः-पुंगवः-ऋषभः; *See* **Excellent;** 'm.-eater' पुरुषादः, नृभुज्, नरभोजिन्; 'm.-hater' मनुष्यशत्रुः-द्वेष्टा, मनुष्यद्वेषी; 'm. of war' महती युद्धनौः; 'm.-slaughter' मनुष्यवधः-घातः-हत्या, प्रमाथः; 'm.-stealing' मनुष्यापहारः. **-**v. t. पुरुषसनाथीकृ 8 U, सैन्यं निविश् c. **-ful,-ly,** *a.* पौरुष(षी *f.*), पौरुषेय(यी *f.*); शूर-वीर-योग्य, महावीर्य, विक्रांत, शूर, वीर्यवत्; पुरुष-नर- in comp.; 'm. deed' पुरुषकारः, पौरुषं 'm. office' पुरुषाधिकारः. **-fully,** *adv.* पुरुषवत्, सवीर्यं, सत्त्वं, सपौरुषं, सविक्रमं, शूर-वीर-वत्, निर्भयं. **-fulness,-liness,** *s.* पौरुषं, वीर्यं, पुरुषकारः, वि-परा-क्रमः, शौर्यं, साहसं. **-hood,** *s.* मनुष्यत्वं, मानुषता, मानुष्यं, पुरुषदशा-धर्मः-भावः. **2** पुंस्त्वं, पौरुषं, ओजस्-तेजस् *n.*, वीर्यं, ऊर्जस् *n.*, यौवनं, तारुण्यं, यौवनावस्था, तारुण्यदशा, प्रौढता, व्यवहारदशा; 'having reached the stage of m.' प्राप्तयौवनः, आरूढयौवनः. **4** वीर्यं, वि-परा-क्रमः, शौर्यं, पौरुषं.
Manacle, *s.* हस्तनिगडः-बंधनं-पाशः. **-**v. t. (हस्तौ) निगडेन बंध् 9 P or संयम् 1 A.
Manage, *v. t.* निर्वह् c., व्यव-स्था c. (स्थापयति), घट् c. (घटयति); सं-पद् c, वि-धा 3 U, प्र-वृत् c., कृ 8 U. **2** अधि-ष्ठा 1 P, अवेक्ष् 1 A; प्र-णी 1 P, शास् 2 P, नियम् 1 P, नियंत्र् 10; निग्रह् 9 P, वशीकृ, दम् c. (दमयति); *See* **Control. 3** विनी, अनुशास्, शिक्ष् c. **4** परिमितं व्यय् 10 (व्यययति). **-**v. i. आचर् 1 P, वृत् 1 A, घट् 1 A, उपायं युज् 10 or चिंत् 10 or क्लृप् c, संवि-धा; *See* **Arrange;** यथा नौ प्रियसखी बंधुजनशोच्या न भवति तथा निर्वाहय (S. 3) 'so m. that &c.' **-able,** *a.* प्रणेय, विधेय, विनेय, वश्य आयत्त, शासनीय, सुकर. **-ed,** *a.* प्रणीत, विहित; नियत, नियंत्रित; प्रयुक्त, घटित; 'well m.' सुघटित, सुविहित, सुप्रयुक्त. **-er,** *s.* निर्वाहकः, प्रणेतृ *m.*, व्यवस्थापकः, अवेक्षकः, प्रवर्तकः, प्रयोजकः, संपादकः, घटकः, अधिकारिन् *m.* अधिकृतः, नायकः, अधिष्ठातृ *m.*, अध्यक्षः, चालकः; 'm. of public affairs' जनकार्याध्यक्षः, पौरकार्यावेक्षकः, जनकार्याधिकारी; 'm. of the treasury' कोशाध्यक्षः, द्रव्याधिकारी. **2** (Stage-m.) सूत्रधारः, स्थापकः. **3** परिमितव्ययिन् *m.* **-ing,** *a.* व्यवस्थापक, कार्याधिकारिन्, कार्यावेक्षक, चालक. **-ment,** *s.* प्रणयनं, नयः, नीति *f.*, निर्वाहः-हणं, घटनं, प्रवर्तनं, करणं, विधानं, अधिष्ठानं, अवेक्षा-क्षणं, व्यवस्थापनं, चालनं. **2** अधिकारः, अधिष्ठातृत्वं, शासन, नियमनं, अध्यक्षता, विनियमः, नियंत्रणं, वशीकरणं. **3** उपायः, प्रयोगः, युक्ति *f.*, उपाय-कल्पना-प्रयोगः, संविधा; 'under his m. of affairs' तस्मिन् कार्याणि अवेक्षमाणे, कार्याध्यक्षे तस्मिन्.
Manakin, *See* **Manikin.**
Manciple, *s.* भोजनाधिकारिन् *m.*
Mandate, *s.* आज्ञा, शासनं, आ-नि-देशः, नियोगः, विधिः; 'written m.' आज्ञापत्रं, शासनपत्रं. **-ory,** *a.* आदेशक, आज्ञापक, शासक.
Mandible, *s.* हनु *m.* *f.*, चिबुकं, पीचं, कुंजः.
Mandrake, *s.* लक्ष्मणा, पुत्रदात्री, पुत्रदा.
Manducate, *v. t.* चर्व् 1 P.

Mane, *s.* केश(स)रः; सटा (of a lion). **-ed,** *a.* केसरिन्.

Manege, *s.* अश्वदमनविद्या-कला.

Manes, *s.* पितरः,स्वधा-श्राद्ध-भुजः; पिंडभाजः, पिंडाशाः (all pl.) पितृगणः-वर्गः-लोकः-जनः; 'offering oblations to the m.' पितृ-कर्म-कार्य-क्रिया-यज्ञः-मेधः, श्राद्धकर्म-क्रिया; 'oblations to the m.' पिंडः, स्वधा, कव्यं, श्राद्धं; 'gifts in honour of the m.' पितृदानं-तर्पणं; 'a day sacred to the m.' पितृतिथि *m. f.*

Mange, *s.* (पशूनां) सिध्मन् *m.*, पामा; *See* **Itch.**

Manger, *s.* द्रोणि, यवादनी, तृणभाजनं-पात्रं.

Mangle, *v. t.* व्यव-छिद् 7 P वि-दॄ 9 P, व्रश्च् 6 P, निकृत् 6 P, लवशः कृत् or खंड् 10 or छिद्. **-s.** वस्त्रमार्जनयंत्रं. **-ed,** *a.* छिन्नभिन्न, विक्षतांग (गी *f.*), व्यवच्छिन्न, क्षतविक्षत, लवशः कृत.

Mango, *s.* आम्रं, आम्रफलं; (tree) आम्रः, चूतः-तकः, रसालः; सहकारः (very fragrant); 'm.-blossom' चूतप्रसवः; 'm.-sprout' सहकारमंजरी.

Mania, *s.* उन्मादः, बुद्धिभ्रमः, *See* **Madness.** 2 महाव्यसनं,एकविषयासक्ति *f.* **-Maniac,** *a.* उन्मत्त, वातुल. **-s.** उन्मत्तः,वातुलः, *See* **Mad.**

Manifest, *a.* स्पष्ट, स्फुट, व्यक्त, प्रत्यक्ष, प्रकाश, प्रकट, सुव्यक्त-स्पष्ट-प्रकाश, परिस्फुट, अभिव्यक्त, प्रकटित, आविर्भूत; प्रादुर्भूत; 'to become m.' प्रादुर्भू 1 P,आविर्भू, प्रकटी-स्पष्टी-भू, प्रकाश् 1 A **-v. t.,** 'make m.' प्रकाश् c., व्यंज् 7 P or c., स्पष्टीकृ 8 U, आविष्कृ, प्रकटी-प्रत्यक्षी-स्फुटी-कृ, विशदीकृ, प्रकटयति (D.), सूच्, दृश् 10, c.; आविर्भूतज्योतिषां ब्राह्मणानां (U. 4.) 'to whom the Supreme Light has m.-ed itself.' **-ation,** *s.* आविष्करणं, प्रकाशनं, व्यंजनं स्फुटीकरणं, &c. 2 व्यक्ति *f.*, प्रकाशता स्पष्टता, आविर्भावः, प्रादुर्भावः, प्रत्यक्षता अवभासः, प्राकट्यं. **-er,** *s.* प्रकाशकः, व्यंजकः. **-ly,** *adv.* व्यक्तं, स्पष्टं, स्फुटं, सुव्यक्तं, परिस्फुटं. **-ness,** *s.* व्यक्तता, स्पष्टता, &c. **-Manifesto,** *s.* प्रकाशन-घोषणा-पत्रं, ज्ञापन-प्रसिद्धि-पत्रं.

Manifold, *a.* *See* under **Many.**

Manikin, *s.* क्षुद्रनरः, माणवकः, मनुष्यकः.

Maniple, *s.* मुष्टि *m. f.* 2 लघुगुल्मः.

Manipulate, *v. t.* हस्ताभ्यां कृ 8 U or वि-धा 3 U; हस्तौ व्यापृ c. or चल् or विक्षिप् 6 P. **-ion,** *s.* हस्तव्यापारः, हस्तादिचालनं-विक्षेपः.

Manna, *s.* (Of bamboos) वंशरो(लो)-चना, त्वक्क्षीरी, वंशजा, शुभ्रा, वंशक्षीरी, वैणवी.

Manner, *s.* प्रकारः, रीति *f.*, विधा, विधिः, रूपं, मार्गः, पर्यायः, क्रमः; पद्धति *f.*, सरणी *f.*; 'in this m.' इत्थं, एवं, अनेन प्रकारेण, &c.; 'in that m.' 'in such a m.' तथा, तेन प्रकारेण, एवंविधं, तथाविधं, एवंरूपेण, &c.; 'in like m.' तथा, तथैव, एवमेव, वद्वत्. 2 (Kind) भेदः, विशेषः, प्रकारः. 3 आकारः, आकृति *f.*, रूपं, मुखचर्या, वदनाकृतिः. 4 (M. s) आचारः, आचरणं, वृत्ति *f.*, वृत्तं, वर्तनं, व्यवहारः, चर्या, रीतिः; नियमः, चरित्रं, शीलं, मार्गः, सम्प्रदायः, धारा, अभ्यासः (habitual m. s); 'good m. s' सदाचारः, सद्वर्तनं, विनयः, सुनीति *f.*, शिष्टाचारः, मर्यादा, सुशीलता, शिष्टता, सभ्यता, शिष्ट-संप्रदायः; 'bad m. s' अमर्यादा, दुराचारः, अनीतिः; कुरीतिः; 'm. s of a country' देशाचारः, देशव्यवहारः; 'violation of good m. s' मर्यादा-विनय-अतिक्रमः. **-ed,** *a.* सुशील, शिष्टाचार, विनीत; 'ill-m.' अशिष्ट, असभ्य, दुःशील, दुर्मर्याद, अविनीत. **-ism,** *s.* एकरीतिसेवनं, एकरसत्वं. **-less,** *a.* अविनीत, दुराचार, अशिष्ट, अमर्याद. **-ly,** *a.* शिष्ट, विनीत, सभ्य, सुशील, सुजन, सदाचार, साधुवृत्त, शिष्टाचार **-adv.** सविनयं, शिष्टवत्.

Manœuvre, *s.* यानप्रकारः, युद्धव्यपदेशः. 2 प्रयुक्ति *f.*, कौशलं, वैदग्ध्यं, उपायः, व्यपदेशः, माया, विदग्धप्रयोगः, कपटोपायः. **-v. i.** विदग्धोपायं रच् 10 or युज् 10, छलं-कपटं; प्र-कृ 8 U.

Manor, *s.* ग्रामाधिपत्यभूमि *f.* स्थानं; 'lord of the m.' ग्रामेश्वरः, ग्रामपतिः.

Mansion, *s.* हर्म्यं, सौधं, गृहं, मंदिरं, भवनं, गेहं, सदनं, निकेतनं, शाला, आयतनं; *See* **House;** 'lunar m.' नक्षत्रं, दक्षजा, विधुप्रिया.

Mantle, *s.* प्रावारः-रकः, अवगुंठनं, आवरणं, पिधानं. **-v. t.** आ-प्र-वृ 5 U, समाकृ 6 P, आ-च्छद् 10. **-v. i.** प्रवृध् 1 A, विस्तृ-वितन् pass.; प्र-वि-सृप् 1 P. 2 उद्गम् 1 P, उत्सृप्, आविर्भू 1 P. 3 उत्सिच् pass., फेनं पते (D.). 4 मुद् 1 A, आनंद् 1 P, उत्सवं कृ 8 U; *See* **Delight.**

Mantua, *s.* स्त्रीवस्त्रं-परिधानं.

Manual, *a.* हस्त्य, हस्त in comp.; 'm. art' शिल्पं, कला; 'm. dexterity' हस्तकौशलं-लाघवं; 'm. labour' श्रमः, आयासः; 'sign m.' स्वाक्षरं, स्वहस्ताक्षरं. **-s.** लघुपुस्तकं, संक्षिप्त-ग्रंथः, सारसंग्रहः.

Manufacture, *s.* निर्माणं, विरचनं-ना, घटनं-ना, उत्पादनं, शिल्पकर्मन् *n.*, शिल्पनिर्माणं 2 शिल्पनिर्मितं-द्रव्यं-वस्तु. **-v. t.** शिल्पेन निर्मा 3 A, 2 P, or क्लृप् c. or रच् 10 or वि-धा 3 U or कृ 8 U. **-al,** *a.* शिल्पिक (की *f*). **-er,** *s.* शिल्पकारः, शिल्पिन् *m.*, शिल्पकः.

-Manufactory, *s.* शिल्पशाला-गृहं, निर्माणशाला-गृहं.

Manumit, *v. t.* दास्यात् मुच् 6 P or c. or मोक्ष् 10. **-Manumission**, *s.* दास्यमोचनं, बंधनमोक्षः

Manumotive, Manumotor, *a.* हस्तप्रेरित.

Manure, *s.* सारः, भूमिलेपः, पुरीषादि *n.* -*v. t.* पुरीषादिना लिप् 6 P, सारं नि-धा 3 U or निक्षिप् 6 P.

Manuscript, *s.* हस्तलेखः-लिखितं, लेख्यं, लिखितं. -*a.* लिखित, हस्तलिखित.

Many, *a.* बहु, बहुल, अनेक, भूयिष्ठ, प्रभूत, प्रचुर, बहुसंख्यक, भूयस्, विपुल, नैक-नाना- in comp.; 'of m. kinds' अनेक-नाना-विध; 'as m. as' 'so m.' यावत्-तावत्, यावत्-संख्यक-तावत्संख्यक, यति-तति; 'how m.' कियत्, कति (pl.); 'of how m. kinds' कतिविध-*a.*, 'in m. places' बहुत्र, अनेकत्र; 'in m. ways' बहुधा, अनेकधा; 'how m. times' कतिकृत्वः, कतिवारान्; 'm. times' बहुशः, भूयो भूयः, मुहुर्मुहुः, अनेकशः, अनेक-बहु-वारं,पुनः-पुनः, बहुकृत्वः; 'so m.' एतावत्,इयत् -*s.* समूहः, समवायः, संघातः; समाजः; 'the good of the m.' समाजहितं. In comp. ex. by बहु or नाना; बहुपर्ण, नानावर्ण, बहुजिह्व, &c. **-Manifold**, 'many-sided' *a.* नानाविध-प्रकार, बहुगुण-रूप, अनेक, अनेक-नाना-रूप, विविध, बहुविध-प्रकार;नाना in comp. **-ly**, *adv.* बहुधा, अनेकधा, नानाविधं. **-ness**, *s.* बाहुल्यं, अनेकता.

Map, *s.* वर्णनं, देशालेख्यं, आलेख्यपत्रं. -*v. t.* (देशादीन्) अभिलिख् 6 P, वर्ण् 10, चित्र् 10.

Mar, *v. t.* हन् 2 P, वि-,नश् c., विलुप् 6 P or c., अपकृ 8 U, क्षण् 8 P, दुष् c (दूषयति); *See* **Spoil**,: 'without m.ring its beauty' लावण्यहानिं विना, रूपक्षतिं विना **-Marplot**, *s.* कार्यविघातकः, विघ्नकरः.

Marasmus, *s.* क्षयः, यक्ष्मन् *m.*, शोषः.

Maraud, *v. i.* लोप्त्रार्थं परिभ्रम् 1, 4 P or उपद्रु 1 P or उपप्लु 1 A. **-er**, *s.* उपद्रविन् *m.*, उपप्लवकारिन् *m.*, लुंठकः. **-ing**, *s.* उपप्लवः, उपद्रवः, लोप्त्रार्थं परिभ्रमणं.

Marble, *s.* मर्मरोपलः, श्लक्ष्णः प्रस्तरः, मणिशिला, शिला, पाषाणः.

Marcescent, *a.* विशीर्यमाण.

March, *v. i.* प्र-या 2 P, प्र-गम् 1 P, प्र-संचल्-इ 1 P, व्रज् 1 P, प्र-स्था 1 A; *See* **Advance**, 'm. against' अभि-या, अभिनिर्-या, प्रति-गम्-व्रज्; संमुखं या; 'who m.es slowly,' मंदगामी; 'who m. es fast' जंघालः, तरस्वी, जवनः, अतिजवः. -*v. t.* प्र-स्था c. (स्थापयति), प्र-या c. -*s.* फाल्गुनचैत्रं, पूर्वचैत्रः. 2 गमनं, यानं, यात्रा, प्रस्थानं, प्रगमनं, प्रयाणं, अभिनिर्याणं; 'at a distance which is some days' m.' त्रिचतुरप्रयाणकमध्ये (Ka. 258) 'going by hasty (forced) m.-es' अविच्छिन्नैः प्रयाणकैर्वहन् (Ka. 340); 'difficult m.' दुर्गसंचरः, संक्रमः; 'm. ing with an army against the enemy' अभिषेणनं; 'a m.-ing army' प्रचक्रं, चलितं; 'a hostile m.' अभिक्रमः, आसारः **-Marches**, *s* देशसीमा-पर्यंतः.

Mare, *s.* वडवा, अश्वा, वामी, तुरगी, वाजिनी.

Margin, *s.* प्रांतः, धारः-रा, पर्यंतः, तटं, उपांतः, सीमा, परिसरः, उपकंठः, कच्छः. **-al**, *a.* प्रांतस्थ, प्रांतवर्तिन्. **-ally**, *adv.* प्रांततः, अनुप्रांतं.

Marinate, *s.* संधितं, संधानं. -*v. t.* सं-धा 3 U उपस्कृ 8 U.

Marine, *a.* सामुद्र (द्री *f.*), समुद्रीय, समुद्रविषयक, समुद्रज, समुद्र (Sea, q. v.) in comp.; 'm.-fight' नौयुद्धं, जलसंग्रामः. -*s.* नौयोधः, समुद्रीयसैनिकः. 2 युद्धनौसमूहः. 3 नाविकप्रकरणं विषयः.

Mariner, *s.* नाविकः, पोतवाहः समुद्रयायिन्-गामिन् *m.*

Marionette, *s.* सूत्रचालिता-पुत्रिका or पुत्रलिका.

Marital, *a.* पति-स्वामि-विषय.

Maritime, *a.* समुद्रीय, समुद्र in comp. 2 नाविक (की *f.*), नाव्य. 3 समुद्रतीरस्थ.

Marjoram, *s.* समीरणः, मरुवकः, प्रस्थपुष्पः, फणिज्जकः, जंबीरः, पर्णासः, कठिंजरः, कुठेरकः.

Mark, *s.* लक्षणं, चिह्नं, अंकः, लिंगं, लांछनं, व्यंजनं, अभिज्ञानं. 2 कलंकः, लक्ष्मन् *n.*, अंकः, बिंदुः; 'm. on the body' सामुद्रं, लक्षणं; 'whose distinctive m. is boldness' साहसलांछनः; 'freckly m.' जडुलः, कालकः, पिप्लुः, तिलकः; 'an interpreter of bodily m. s' सामुद्रिकः 3 ले (रे) खा, अंकः. 4 लक्ष्यं, शरव्यं, वेध्य, बाणलक्ष्यं; लक्षं; 'hitting the m.' लक्ष्यभेदः; 'hit the m.' लक्ष्यं भिद् 7 P or व्यध् 4 P; 'wide of the m.' अप्रस्तुत, अप्रास्ताविक (की *f.*). -*v. t.* अंक् 10 चिह्नयति-मुद्रयति (D.). लांछ् 1 P. 2 कलंकयति-मलिनयति (D.). मलिनी-कलुषीकृ 8 U. 3 लिख् 6 P, रेखाः लिख्. 4 लक्ष 10, आ-उप-°; नि-इ-प्र-सं-अव-ईक्ष् 1 A. अवधा 3 U; आलोच् 10, विमृश् 6 P; निरूप् 10; 'm. out' परिच्छिद् 7 P. सीमां निर्दिश् 10 or निर्दिश् 6 P, लक्ष्,बाह्यरेखां लिख्. **-ed**, *a.* चिह्नित,मुद्रित, अंकित,कृत-लक्षण-लांछन, मुद्रांकित; 'an arm m. with the scar of the bow-string' मौर्वीकिणांकः भुजः

(S. 1.). -**Marksman**, *s.* लक्ष्यभेदिन्-वेधिन् *m.*, सुसंधानी, शराभ्यासकुशलः, धनुर्विद्.

Market, *s.* विपणि-णी *f.*, आपणः, निषद्या, पण्यवीथी,पण्यवीथिका, हट्टः, पण्य or विक्रयशाला or स्थानं, निगमः. 2 क्रयविक्रयः, विपणः. -*v. t.* पण् 1 A, व्यवहृ 1 P; 'm.-day' हट्टदिवसः; 'm. place' *See* (*s.*); 'm.-rate or-price' पण्यमूल्यं, अर्घबलाबलं; 'm.-town' मुख्यनगरं, कर्वटः. -**able**, *a.* पण्य, पण्यार्ह, क्रयविक्रययोग्य.

Marking-ink, *s.* अक्षय्यमसी.

Marl, *s.* चिक्कणमृत्तिका.

Marmalade, *s.* मिष्टान्नं, स्वादुफलं.

Marmorean, *a.* पाषाणनिर्मित.

Marmoset, *s.* क्षुद्रप्लवंगः वानरः.

Maroon, *a.* घनारुण, घनरक्त.

Marquee, *s.* पटवासः-मंडपः, उपकार्या, वस्त्रगृहं.

Marrow, *s.* मेदस् *n.*, मज्जा, वपा, वसा, अस्थि-स्नेह-सारः, अस्थिजं, स्निग्धा. 2 सारः-रं, गर्भः, मुख्यांशः; 'he has knocked the m. out in no time' अचिरादेव तेन सर्वस्य सारः निष्कृष्टः-गृहीतः. -**less**, *a.* मज्जा-मेदो-हीन, अ-निः-सार. -**y**, *a.* मेदस्विन्, सारवत्, ससार.

Marry, *v. t.* वि-उद्-वह् 1 P, परि-णी 1 P, उप-यम् 1 A, प्रति-परि-ग्रह् 9 P. 2 (Take for husband) (पतिं) विद् 6 U or लभ् 1 A or अधिगम् 1 P. वृ 5 U, 10 (वरयति), वृ 9 U, पत्या संयुज् pass. 3 (Give in marriage) विवाहं कृ c., पाणिं ग्रह् c., प्र-दा 3 U, पाणिग्रहणं सं-पद् c.; विवाहेन संयुज् 7 U, 10 or संबंध् 9 P, -*adv.* नूनं, खलु; *See* **Indeed** -**age**, *s.* विवाहः,उद्वाहः, उपयमः, परिणयः, पाणिग्रहः-हणं, पाणिपीडनं, दारपरिग्रहः-अधिगमनं-क्रिया; 'give in m.' विवाहविधिना दा or प्रति-पद् c.; 'm.-contract' वाङ्निश्चयः; 'm.-price' शुल्कः-ल्कं; 'm.-gifts' यौतकं, औद्वाहिकं, पारिणाय्यं, सुदायः. 'm.-string' (विवाह-)कौतुकं, मंगलसूत्रं. -**ageable**, *a.* विवाहयोग्य, परिणेय, विवाहवयस्क, उद्वाहोचित. -**ed**, *a.* ऊढ, परिणीत, उपयत, कृतविवाह, जातोपयम, निविष्ट; 'a m. man' श्रीमान्, कुटुंबी, सभार्यः, कृतदारः, सपत्नीकः; 'a m. woman' सभर्तृका, पतिपत्नी, सधवा, सुवासिनी; 'twice m.' पुनर्भूः, दिधिषु-षूः; 'one m. before his elder brother' परिवेत्तृ; 'the sin of such marriage' पारिवेद्यं

Mars, *s.* मंगलः, भौमः, अंगारकः,भू-मही-सुतः लोहितः, रुधिरः, कुजः, लोहितांगः. 2 कुमारः कार्तिकेयः, गुहः, स्कंदः, शक्तिधरः, षडाननः, महासेनः, शरजन्मन् *m.*, सेनानीः. अग्निभूः, विशाखः, षाण्मातुरः.

Marsh, *s.* अनूपदेशः, कच्छः, कच्छभू-भूमि *f.*, सजल-जलाढ्य-भूमिः. -**y**, *a.* अनूप. आनूप (पी *f.*), जलाढ्य, जलपूर्ण, सजल. जलमय (यी *f.*).

Marshal, *s.* बलाध्यक्षः, संविधातृ *m.*. व्यवस्थापकः. -*v. t.* विन्यस् 4 U, वि-रच् 10. व्यूह् 1 U. क्रमेण रच् or स्था c.(स्थापयति). संधि धा 3 U.

Mart, *s.* क्रयविक्रयस्थानं, आपणः; *See* **Market**.

Martial, *a.* युद्ध-रण-विषयक, सांग्रामिक-सामरिक (की *f.*). 2 रणयोग्य, समरोचित. 3 रणप्रिय, समरासक्त, समर-रण-काम. 'm. music' रणवाद्यं.

Martinet, *s.* तीक्ष्ण or उग्र-दंडः or शासनः

Martingal, *s.* तलिका, अधोबंधनं.

Martyr, *s.* स्वधर्मार्थ-स्वमतार्थं त्यक्तप्राणः or देहत्यागिन् *m.* or त्यक्तजीवितः; 'a blessed m.' सुगृहीतनामा &c. -**dom**, *s.* स्वधर्मार्थ-स्वमतरक्षणार्थं प्राण-जीवित-त्यागः or प्राणोत्सर्गः or देहन्यासः.

Marvel, *s.* कौतुकं, आश्चर्यं, विस्मयहेतुः चमत्कारः, अद्भुतं, चित्रं, चित्र अद्भुत-वस्तु *n.* -*v. i.* वि-स्मि 1 A, साश्चर्य-सविस्मय-अ. भू 1 P, विस्मयेन आकुलीभू or अभिभू pass. -**lous**, *a.* अद्भुत, साश्चर्य, चित्र आश्चर्यकर (री *f.*), विस्मयावह, आश्चर्यः 'a m. tale' चित्रा कथा; 'a m. deed' अद्भुतं कर्म. -**lously**, *adv.* अद्भुतं, चित्र -**lousness**, *s.* चित्रता, &c.

Mascot,-**te**, शुभवस्तु *n.*

Masculine, *a.* पौरुष(षी *f.*),पुंजातीय. अक्लीब, पुं-पुरुष- in comp. 2 पुरुषशील-स्वभाव,पुरुषप्रकृति; 'in gender' पुंस्, पुल्लिंग; 'the word दार is plural and m. (of m. gender) दाराः पुंभूम्नि; 'a m. woman' ऋषभी. -**ly**, *adv.* पुंवत्, पुरुषवत्. -**ness**, *s.* पुंस्त्वं, पौरुषं.

Mash, *v. t.* संपिष् 7 P, सं-मृद् 9 P, क्षुद् 7 U, चूर्ण् 10. -*s.* संपेषः, संचूर्णनं उद्पेषः

Mask, *s.* वर्णकः, वर्णिका, कपट-छद्म-मुखं. 2 छद्मन् *n.*, कपटः-टं, छलं, व्याजः, अप-व्यपदेशः. 3 कृत्रिम-छद्म-वेशः; 'to throw off the m.' (पूर्वनिगूढान्) निजमनोरथान् आविष्कृ 8 U or प्रकटीकृ. -*v. t.* छद्ममुखेन गुह् 1 U or प्रच्छद् 10; गुह्, अपवृ c.. गुप् 1 P. -**ed**, *a.* छद्म-गुप्त-मुख (खी *f.*), सवर्णिक. 2 छद्मवेशिन्, कपटवेश; *See* **Disguised**, 3 गुप्त, छन्न, गूढ. -**er**, *s.* छद्मवेशिन् *m.*,कपटवेषिन् *m.*, &c.

Mason, *s.* लेपकः, लेपकारः, सुधाजीविन् *m.*, पल्गंडः. **-ry,** *s.* सुधा-लेप-कर्मन् *n.*, इष्टकारचनं-निर्माणं.

Masquerade, *v. i.* छद्मवेशं धृ 10, विडंब् 10, कपटवेशं परि-धा 3 U. **-s.** छद्म-कपटवेशधारणं, छद्मवेशक्रीडा, विडंबनक्रीडा. **-er,** *s.* छद्मवेशधारिन् *m.*, कपटवेशिन् *m.*

Mass, *s.* पिंडः, घनः, गंडः. **2** राशिः, नि-प्रचयः, निकरः, समूहः, ओघः, पुंजः, संघः, गणः, समाहारः, निवहः; *See* **Multitude,** 'in m. es' संघशः, गणशः; 'in the m.' साकल्येन. **-ive, -y,** *a.* स्थूल, गुरु, स्थूलाकार, बृहत्, बृहत्-स्थूल-परिमाण, गुरुभार, सभार; पिंडित, पिंडाकार. **-iveness,** *s.* स्थूलता, गुरुत्वं, महत्त्वं, गुरुभारः.

Massacre, *v. t.* (क्रौर्येण) हन् 2 P, व्यापद् c., सूद् 10, वि-शस् 1 P, प्रमथ् 9 P, निर्दल् c. (दलयति); *See* **Kill.** **-s.** प्रहारः, विशसनं, घातः, प्रमाथः, निषूदनं, व्यापादनं; *See* **Killing.**

Massage, *s.* अंग-मर्दनं-संवाहनं.

Mast, *s.* कूपकः, कूपदंडः, गुणवृक्षकः

Master, *s.* प्रभुः, ईश्वरः, ईशः, नाथः, स्वामिन् *m.*, अधिपः, अधिपतिः, भर्तृ *m.*, सेव्यः; *See* **Lord,** 'serving two m. s' उभय-वेतन, उभयस्वामिक; 'one's own m.' स्वतंत्र, स्वाधीन, अपरायत्त; 'to be m. of' ex by (*s.*) or प्र-भू 1 P, ईश् 2 A (with gen.); 'I am not m. of myself' अप्रभुरस्मि आत्मनः (Ka. 36), न प्रभवात्मनः, गात्राणामनीशोस्मि संवृत्तः (S. 2). **2** अधिकारिन् *m.*, अध्यक्षः, अधिष्ठातृ अधिकृतः, अवेक्षकः, अधीशः, नायकः, पतिः, मुखरः, अग्रणीः; 'm. of a family' कुलपतिः, कौटुंबिकः, कुटुंबिन् *m.* 'm of the horse' अश्वाध्यक्षः; 'm. of sports' नर्म-केलि-सचिवः. **3** शिक्षकः, गुरुः, अध्यापकः, आचार्यः, उपाध्यायः. **4** पंडितः, कुशलः, पारगतः, निपुणः, व्युत्पन्नः, 'm.-hand' उत्तम-परम-कर्मकारः; 'm.-workman' मुख्यशिल्पिन् *m.*, कर्मकाराग्रणीः; 'm.-piece' अप्रतिमं-निरुपमं-कृत्यं, अत्युत्तमं-अत्युत्कृष्टं-कर्म 'm. stroke' वैदग्ध्य-चातुर्य-कर्म, अत्युत्तमक्रिया. **-v. t.** अभ्यंतरीकृ 8 U, पारे गम् 1 P; 'who has m. ed all sciences' सकलशास्त्रपारंगतः. **2** वशीकृ, दम् c. (दमयति); परा-अभि-भू 1 P, जि 1 P. **-ly,** *a.* अनुपम, अप्रतिम, अत्युत्तम, अद्वितीय, अत्युत्कृष्ट, परम; अतुल, अतिकुशल-निपुण. **-adv.** अत्युत्कृष्टं, परमनिपुणतया. **-ship,** *s.* प्रभुत्वं, स्वामित्वं, आधिपत्यं, ऐश्वर्यं, प्राधान्यं, &c. **-y,** *s.* प्रभुत्वं, ऐश्वर्यं, आधिपत्यं, अधिकारः, अधिष्ठातृत्वं, स्वाम्यं. **2** उत्कर्षः, श्रेष्ठता, आधिक्यं, प्राधान्यं, मुख्यता, परम-उत्तम-श्रेष्ठ-पदं. **2** प्रावीण्यं, अतिनैपुण्यं, परमकौशल-पाटवं, पारंगतता, प्रतिष्ठा; 'you have attained great m. over all sciences of arms' गतोसि सर्वास्वायुधविद्यासु परां प्रतिष्ठां (Ka. 77); 'to have m. over' अभि-भू, प्र-भू, ईश्, वशीकृ; *See* above.

Masticate, *v. t.* चर्व् 1 P. 10, संदंश् 1 P. **-ion,** *s.* चर्वणं, दंशनं, दंतैर्निष्पेषणं. **-ory,** *a.* चर्वणोचित. **-s.** चर्व्यं.

Mat, *s.* कटः, किलिंजं, आस्तरणं, पादपाशी. **-v. t.** कटैः आस्तृ 5 U. **2** संग्रंथ् 9 P, संश्लिष c., जटिलीकृ 8 U; 'm. ed hair' जटा, सटा, जूटकं, जटा-सटा-जूटः; 'having m. ed hair' जटिल, जटिन्.

Match, *s.* समः, समानः, तुल्यः, समान-तुल्य-बलः, तुल्यशक्तिः-पराक्रमः, प्रतिद्वंद्विन् *m.*; 'let us (two) make a m.' आवां प्रतिद्वंद्विनौ भवाव. **2** (One of a pair) यमः, यमकः-ल, युग्मकः, समान-सम-कक्षः. **3** विवाहः, विवाह-प्रेम-संबंधः-घटना-योगः; 'bringing together a m. of equal merits' समानयंस्तुल्यगुणं वधूवरं (S. 5.). **4** युद्धं; 'a m. of cocks &c.' प्राणिद्यूतं, समाह्वयः; 'boxing m.' मल्लक्रीडा-युद्धं, मुष्टामुष्टि युद्धं. **5** अग्निशलाका; 'to be a m. for' ex. by अलं with dat. दैत्येभ्यो हरिरलं (S.K.); 'one wrestler is a m. for another' अलं मल्लो मल्लाय, प्रभवति मल्लो मल्लाय; 'to be more than a m. for' अतीत्य-अतिक्रम्य-वृत् 1 A or स्था 1 P; अतीत्य हरितो हरींश्च वर्तते वाजिनः (S. 1); or by अधिक-*a.* or अतिरिच्-विशिष्-pass., with abl.; सेनाशतेभ्योधिका बुद्धिः (Mu. 1). **-v. t.** तुल् 10 (तुलयति), तुल्यी-समी-कृ 8 U, उप-प्रति-मा 3 A; तुल्यतया घट् c. (घटयति) or समा-नी 1 P or संयुज् 7 U, 10. **2** समं दृश् c., प्रतिरूपं-उपमां-निर्दिश् 6 P; oft. ex. by तुल्य, सम (Equal, q. v.); 'it was a well-m. ed fight' तुल्यप्रतिद्वंद्वि बभूव युद्धं (R. vii. 37); 'palaces can m. you' प्रासादास्त्वां तुलयितुमलं (Me. 65); 'he will m. you in strength' बलविषये स त्वया तुलां समारोक्ष्यति. **3** तुल्यबलं-समं युज् or पुरस्कृ, प्रतियुध् c. **4** विवाहार्थं प्रति-पद् c. or प्र-दा 3 U, 1 P, परि-णी c., उद्वह् c. **5** सं-,युज्, समा-धा 3 U, अनुरूप-*a.* कृ. **-v. i.** युज् pass., उप-मा pass., तुल्य-अनुरूप-*a.* भू; सदृशी-अनुगुणी-भू, संवद् 1 P. **2** संगम् 1 A, संमिल् 6 P, सं-इ 2 P, संगमनुव्रज् 1 P, संयुज् pass. **3** विवाहार्थं दा-pass. **-ed,** *a.* तुल्यबल-शक्ति, समविक्रम; उपमित, &c. **2** विवाहित, कृतविवाह, कृतोपयम. **-less,** *a.* अतुल, निरुपम, अनुपम, अद्वितीय, अप्रतिरूप, अप्रतिम अनुपमेय; अतुल्य. असदृश

(श्री *f.*). **-lessly,** *adv.* अनुपमं, अप्रतिरूपं. **-lessness,** *s.* अनुपमता, &c.

Mate, *s.* सहायः, सहचरः, मित्रं, संगिन् *m.*, सखि *m.* **2** भर्तृ *m.* स्वामिन् *m.* पतिः; (female) सहचरी, सखी, पत्नी, वधूः, भार्या, प्रिया, दयिता; *See* **Wife;** 'an elephant's m.' वशा, करिणी, हस्तिनी **3** सहायः, सहकारिन् *m.*

Material &c., *See* under ***Matter.***

Maternal, *a.* मातृक (की *f.*), मातृसंबंधिन्; मातृ-in comp.; 'm. uncle' मातुलः (लानी *f.*); 'm affection' अपत्यस्नेहः, पुत्रप्रीति *f.*, वात्सल्यं; 'm. duty मातृधर्मः.

Mathematics, *s.* गणितं, गणितशास्त्रं-विद्या, संख्या-परिमाण-विद्या, गणनाविद्या. **-*Mathematic,-al,*** *a.* गणितविषयक, गणितसंबंधिन्. **2** गणितशास्त्रानुरूप. **-ally,** *adv.* गणितानुसारेण. **-ian,** *s* गणितविद्याज्ञः, गणितशास्त्रज्ञः-विद्, गणितज्ञ..

Matin, *a.* प्रातःकालीन, प्रातःकालिक (की *f.*), प्रगेतन (नी *f.*), प्रातर् in comp. **-s.** (M. s) प्रातरुपासना; प्रातःकृत्यं-कर्मन् *n.*

Matrice, *s.* गर्भाशयः, जरायुः. **2** मुद्राक्षर संस्कारः.

Matricide, *s.* मातृहत्या-वधः-घातः. **2** मातृघातिन्-मातृहन् *m.*, मातृघ्नः. मातृघातकः.

Matriculate, *v. t.* संकारपूर्वं विद्यालयं प्रविश् *c.* **-s.** विद्यालयप्रविष्टः.

Matrimony, *s.* विवाहः, परिणयः, उपयमः, उद्वाहः; *See* **Marriage.** **-ial,** *a.* वैवाहिक-औद्वाहिक-(की *f.*); 'm. alliance' विवाहसंबंधः. **-ially,** *adv.* विवाहविध्यनुरूपं.

Matron, *s.* पुरंध्री, आर्या, प्रौढा, गृहिणी, गेहिनी, पुत्रिणी, सुतिनी, कुटुंबिनी, पुत्रवती. **-ly,** *a.* पुरंध्रीयोग्य, गृहिणीसदृश (शी *f.*); धीर. गंभीर, प्रौढ, आर्य, विनीत.

Matter, *s.* द्रव्यं, वस्तु *n.*, स्थूल or घन-द्रव्यं or वस्तु भौतिकवस्तु, साकारद्रव्यं, मूर्ति *f.* **2** साधनं, प्रकृति *f.*, उपकरणं, कारणं, उपादानं. **3** द्रव्यं, वस्तु, पदार्थः; अर्थः. विषयः, प्रकरणं, पदं, आस्पदं, प्रस्तावः, प्रसंगः. **4** प्रयोजनं, हेतुः, कारणं. कार्यं, व्यापारः, अर्थः. **5** सारः, तत्त्वं, अर्थः, गुरुत्वं, गौरवं, महत्त्वं, प्रभावः. **6** पूयं, दूष्यं, क्षतजं, पूयरक्तं-शोणितं; 'm. in hand' प्रकृतं, प्रस्तुतं; 'm. of dispute' विवादवस्तु-विषयः-आस्पदं &c.; 'it is of no m.' यत्किंचित्करमेतत्, निरर्थकं; सूक्ष्मविचारस्याविषयः; 'an important m.' गुर्वर्थः; 'of no m.' निरर्थक, निःसार, अगुरु; 'what is the m. with her' किं तस्या वृत्तं, कस्तस्या वृत्तांतः. **-v.** *i.* Ex. by अर्थः, or by किं, कार्यं with instr.; 'what m. s it to me' किं मम तेन कार्यं, कोऽर्थः &c.; 'it m. s very little', 'it m. s not' लघ्वर्थमेतत्, नार्थं कनीयानर्थः, **2** पूयपूर्ण-*a.* सृ 1 P, पूयं उत्पद् *c.* **-y,** *a.* पूयपूर्ण-युक्त-गर्भ, सपूय. **-*Material.*** *a.* भूतात्मक, भौतिक (की *f.*), भूतमय (यी *f.*), आधि-पांच-भौतिक, मूर्त, द्रव्यमय, प्राकृतिक (की *f.*); घन, स्थूल, जड. **2** अपारमार्थिक (की *f.*), अनात्मीय. **3** सारवत्, ससार, वास्तविक (की *f.*). **4** गुरु, महत्, परमार्थ, गुर्वर्थ; आवश्यक (की *f.*), मुख्य, प्रधान, विशिष्ट; *See* **Principal;** 'm. world' भूतसृष्टि *f.*, स्थूलं जगत्; 'm. body' स्थूल-जड-देहः; भौतिकपिंडः; 'm. cause' प्रकृतिः, उपादानं, उपादानकारणं; 'proximity being not m.' सान्निध्यस्य अकिंचित्करत्वात् (S. B. 141). **-s.** साधनं, उपकरणं, द्रव्यं, कारणं, उपादानं, प्रकृतिः, पदार्थः, साधनवस्तु; 'all m. s.' सामग्री, सज्जा, संभारः, द्रव्य or उपकरणसामग्री or संभारः; 'writing m. s.' लिपिसज्जा, लेखनसाधनानि; 'the m. of cloth' वस्त्रयोनिः-प्रकृतिः. **-ism,** *s.* लोकायतं, अनात्मवादः, चार्वाकमतं. **-ist,** *s.* लोकायतिकः, अनात्मवादिन् *m.*: विवादिन् *m.* **-ity,** *s.* भौतिकत्वं, मूर्तिमत्त्वं, &c. **-ly,** *adv.* अर्थतः, वस्तुतः, तत्त्वतः, परमार्थतः, सारतः, प्रकृतितः, प्रकृत्यैव.

Mattock, *s.* खनित्रं, टंकः, पाषाणदारणः.

Mattress, *s.* (मृदु-)आ-सं-स्तरः, शयनीयं, आस्तरणं, तूलिका.

Mature, *a.* पक्व, सु-परि-पक्व, परिणत, पक्वतामापन्न, पाकोन्मुख (खी *f.*), फलोन्मुख. **2** संपन्न, सं-परि-पूर्ण, प्रौढ, सिद्ध; 'm. deliberation' सुविचारः, प्रसमीक्ष्य-सुविमृश्य-विचारः, सुसमीक्षा, सुविमर्शः. **-v.** *t.* परिपाकं नी 1 P, परि-णम् *c.* (णमयति), पक्वतां-पाकं-उत्पद् *c.*, पच् *c.*; सं-पद् *c.*, साध् *c.*, सिद्धीकृ 8 U, कठोरीकृ; कलाकलापालोचनकठोरमतिभिः (Ka. 7) 'whose mind was m. ed by studying &c.' **-v.** *i.* पच् pass., परिणम् 1 P, पाकं-परिणामं-इ or या 2 P or गम् 1 P; कठोरी-प्रौढी-भू 1 P; परिणतप्रज्ञस्य कथेर्वाणी (U. 7) 'of m. ed intellect.' **-ate,** *v. t.* पच् *c.*, परि-णम् *c.* **-v.** *i.* पच् pass., पक्वीभू, पूयपूर्ण-*a.* भू. **-ation,** *s.* पाकः, विपरि°,-परिणति *f.*, परिणामः. **2** सपूयत्वं, पूयस्रावः. **-ative,** *a.* पाकल, पाचन, पचिष्णु, पूयजनन (नी *f.*). **-ity, -ness,** *s.* पाकः, वि-परि°-, परिणामः, विपक्वता, परिणति *f.*, प्रौढ-पक्व-दशा, पक्वपरिणत-अवस्था, पक्वभावः, कठोरता, प्रौढता, सिद्धि *f.*, संपूर्णता. **-ly,** *adv.* सपरिणामं, सपाकं. **2** सुसमीक्ष्य, सुविमृश्य, सुविचार्य, सम्यगवधार्य. **-*Maturescent,*** *a.* आपक्व. परिणामोन्मुख.

Matutinal, Matutine, *a.* प्रातःकालिक-प्राभातिक-(की *f.*), प्रगेतन (नी *f.*), उषस्य, प्रातर् in comp.

Maudlin, *a.* आमत्त, मत्तप्राय-कल्प
Maugre, *adv.* *See* 'In spite of' under **Spite.**
Maul, *s.* स्थूलमुद्गरः, घनः. **–v.** *t.* मुद्गरेण-त्सुद्गेन म-हृ 1 P or तड् 10. 2 वि-रूप् 10, विकृ 8 U.
Mausoleum, *s.* चैत्यं, समाधिः.
Maw, *s.* उदरं, जठरः-रं.
Mawkish, *a.* अरस, नीरस, निःसार; बीभत्स, जुगुप्सावह.
Maxillar,-y, *a.* हनुसंबंधिन्, हनु in comp.
Maxim, *s.* सूत्रं, उक्ति *f.*, वचनं, वाक्यं, विधिः, तत्त्वं, नियमः, आ-नि-देशः, चोदना, कल्पः, सिद्धांतः; 'moral m.' नीतिवाक्यं, सदुपदेशवचनं
Maximum, *s.* उत्तम-परम-संख्या.
May, *v.* Gen. ex. by Potential of verbs. **2** (Showing wish or blessing) ex. by Benedictive or Imperative, 'm. god Siva protect you' पातु देवः शिवो वः; 'm. I be satisfied' कृतार्थो भूयासं. **3** (Liberty) gen. ex., by Pot., *See* **Liberty. 4** (Contingency) by Pot., with or without कदाचित्. **–s.** वैशाखज्येष्ठं.
Mayor, *s.* नगराध्यक्षः, पुराग्रणीः. **–Mayoralty,** *s.* पुराध्यक्षता, नगराधिकारः.
Maze, *s.* गहनं, कुटिलमार्गः, सुगहनस्थानं, दुर्निर्गमं स्थानं. **2** वक्रता, गहनता, कौटिल्यं, वैवश्यं. **–y,** *a.* गहन, दुर्निर्गम, कुटिल, जिह्म, अतिवक्र.
Mead, *s.* मधु, मधुपानीयं. **2 Meadow,** q. v.
Meadow, *s.* क्षेत्रं, गोप्रचारः, केदारः. **2** स्थली, वनस्थली, शाद्वलं, यवसस्थानं; 'm. grass' यवसं. **-y,** *a.* शाद्वल, यवसीय.
Meagre, *a.* क्षाम, कृश, क्षीण; *See* **Lean. 2** असार, विरस, नीरस, फल्गु, (style); वंध्यं, रूक्ष (soil). **3** अपूर्ण, स्वल्प, तनु, स्तोक. **–ly,** *adv.* कार्श्येन, स्वल्पं; 'm. attended' तनुपरिवार. **–ness,** *s.* कृशता, क्षीणता, क्षामता, रूक्षता. तनुता, स्वल्पता, &c.

Meal, *s.* सक्तु (*m.* pl.), क्षोदः, चूर्णं, पिष्टं. **2** भोजनं, अशनं; आहारः, आहारविधिः; 'took his m. s' आहारविधिमकरोत्, भोजनं निर्वर्तयामास, शरीरस्थितिं समपादयत्; 'good m.' सुभोजनं; 'morning m.' प्रातराशः. **–y,** *a.* सचूर्ण, क्षोदमय (यी *f.*), **2** कोमल, मसृण, मृदु, चूर्णसदृश (शी *f.*): m. mouthed' मृदुभाषिन्, कोमलवाच्.
Mean, *a.* मध्य, मध्यपरिमाण-प्रमाण, मध्यम. **2** मध्य, मध्यम, मध्यस्थित, व्यवहित, मध्यवर्तिन्, अंतर्गत; 'in the m.-while' 'in the m.-time' अत्रांतरे. **3** नीच, अपनि-कृष्ट, अधम, जघन्य, कदर्य, कुत्सित, नि-, हीन, अनार्य, खल, दुष्ट, विवर्ण, पामर, प्राकृत, अपसद्, क्षुल्लक, याप्य, अवम, अवद्य, गर्ह्य, लघु, कुपूय, खेट in comp., अणक, रेफ; तुच्छ, क्षुद्र, कृपण, दीन, (mind &c.). (in birth) हीन-नीच-जाति, अंत्यजातीय, अकुलीन, कु or का in comp.; 'm.-spirited' लघुचेतस्, क्षुद्रमानस, कृपणबुद्धि, कापुरुष, अधमवृत्ति. **–v.** *t.* उद्दिश् 6 P, इष् 6 P, अभिप्र-इ 2 P; oft. ex. by desid. forms, or by काम or मनस् in comp. with inf.; 'now what do you m. to do' अथ भवान् किं कर्तुमनाः or किं चिकीर्षति; *See* **Intend. 2** गम् c. (गमयति), सूच् c., सुत् c., अभि-धा 3 U, सूच् 10, निर्दिश्; gen. ex by वृत् 1 A with loc., or by loc. simply; by अर्थ, पर, वाचिन् in comp.; ज्योतिः-शब्दस्तेजसि वर्तते (S. B. 146); अत्र अपचितिशब्दः पूजार्थः-पूजापरः-पूजावाची &c.; 'a speech m. ing censure' निंदापरं वचः; 'what is meant by telling a lie' असत्यमिति यदुच्यते तेन किं गम्यते, or असत्यभाषणस्य कोऽर्थः; what can all this m.' कः प्रकारः, किमेतत् (Mal. 5), किं नु एतत्स्यात् (Mal. 1). **–s.** मध्यमपरिमाणं, मध्यता, मध्यं, समप्रमाणं, समपक्षः. **2** अंतरं, अभ्यंतरं, मध्यावधिः, अंतरालं. **3** परिमितता, अनतिक्रमः. **4** (Means) साधनं, उपकरणं, उपायः, करणं, द्वार, योगः, गति *f.*, साहाय्यं, सामग्री, कारणं. हेतुः; oft. ex. by instr. **4** आयः, विभवः; द्रव्यं, धनं, सामर्थ्यं, शक्ति *f.*, धनागमः; 'don't live beyond your m.' आयमर्यादां मातिकाम, यथाविभवं-यथाशक्ति &c. व्ययं कुरु; 'having moderate m.' नातिधन, अल्पविभव; 'by all m.' सर्वथा, सर्वप्रकारेण, अवश्यं, नूनं, खलु, अवश्यमेव; 'by no m.' न सर्वथा, न कथंचन, न कथंचित्; 'by any m.' येन केन प्रकारेण, यथा कथंचित्, कथमपि, कथंचन, कथंचित्, कथं कथमपि; 'm. of subsistence' जीवन-साधनं-उपायः-हेतुः; उपजीविका. **–ing,** *s.* अभिप्रायः, उद्देशः, आशयः, अर्थः, तात्पर्यं, भावः, आकूतं, इंगितं, आकांक्षा. **2** विवक्षा, विवक्षितं, अर्थः; 'the m. of a word' पदार्थः; 'literal m.' अवयवार्थः, पदार्थः, शब्दार्थः; 'hidden m.' मर्मन् *n.*, गूढार्थः; 'what is the m. of this laughter' किंनिमित्तोयं हासः. **–a.** अर्थवत्, सार्थ, पूर्णार्थ, चरितार्थ, साकूत; 'casting at me a m. look' साकूतं मां निर्वर्ण्य. **–ingless,** *a.* निरर्थक, अनर्थक, निष्कारण, अनिमित्त. **–ingly,** *adv.* सार्थं, साकूतं, सेंगितं. **–ly,** *adv.* कृपणवत्, अधमवत्, दीनं, &c.; सावज्ञं, सावमानं, लाघवेन; 'm. born' हीनजाति, अधमवर्ण; 'm, attired' कृपण-अनार्य-वेष. **–ness,** *s.* नीचता, अधमता, कदर्यता, कुत्सितता, &c.;

'm. of birth' अकुलीनता, अपकृष्टं जन्म.

Meander, *v. i.* वक्रं-कुटिलं-जिह्मं-चल् or सृप् 1 P or या 2 P; *See* **Wind.** –*v. t.* कुटिलीकृ 8 U. –*s.* वक्रता, जिह्मता, कौटिल्यं, वक्र-जिह्म-कुटिल-गति *f.*, सर्पगतिः. **–ing,** *a.* वक्र, कुटिल-जिह्म-सर्प-गति, विसर्पिन्, विषमगति.

Measles, *s.* मसूरिका.

Measure, *v. t.* मा 3 A, 2 P, प्र-परि-°; तुल् 10, मानं निरूप् 10 or ज्ञा 9 U. **2** गण् 10. **3** विभज् 1 U, परि-क्लृप् c.; *See* **Divide.** **3** लंघ् 1 A, 10, अतिक्रम् 1 U, 4 P, अति इ 2 P. –*v. i.* Ex. by प्र-परि-माण, मात्र, मित, परिमित in comp. –*s.* मानं, प्र-परि-माणं, (fig. also); 'm. ing rod' मानदंडः; 'm. of capacity' प्रतीमानं, प्रस्थः. **2** वि-, भागः, अंशः. **3** प्रमाणं, पर्यंतः, मात्रा, मर्यादा, सीमा; 'in some m.' ईषत्, किंचित्, अल्पमात्र; 'beyond m.' अतिमात्रं, नितांतं, अतीव, भृशं. **4** उपायः, प्रयोगः, साधनं, युक्ति *f.*, प्रवृत्ति *f.*, क्रिया, उपचारः; 'take m. s' उपायं प्रयुज् 7 A, 10 or आश्रि 1 U or अवलंब् 1 A, कार्ये प्रवृत् 1 A; 'mild m.' सामन् *n.*, सामोपायः. **5** छंदस् *n.*, वृत्तं. **6** तालः, लयः; 'the steps are in m.' पादन्यासो लयमनुगतः (M. 2); 'the m. of a vowel' मात्रा; 'in musical m.' स्वरबद्ध -*a.* **7** अपवर्तः; 'having a common m.' सापवर्त. **–ed,** *a.* मित, परिमित; नियत, निबद्ध; *See* **Limited.** **2** सम, समान, धीर. **–er,** *s.* मापकः, माननिरूपकः. **–less,** *a* अमित, अपरिमाण. **–ment,** *s.* मापनं, मानं, प्र-परि-माणं, प्र-परि-मिति *f.*; 'rough m.' स्थूलमानं; 'accurate m.' सूक्ष्ममानं.

Meat, *s.* आमिषं, मांसं, मांसाहारः; 'butcher's m.' सौ(शौ)नं. **2** अन्नं, भोजन, आहारः; खाद्यं; 'seller of m.' मांसिकः, मां(शौ)-निकः, वैतंसिकः, कौटिकः.

Mechanic, &c. *See* under **Machine.**

Medal *s.* मुद्रा, कीर्तिमुद्रा, प्रतिष्ठामुद्रा. **–list,** *s.* मुद्राशास्त्रज्ञः. **2** लब्धकीर्तिमुद्रः.

Meddle, *v. i.* अन्यव्यापारेषु व्यापारं कृ 8 U, (अन्यव्यापारेषु) व्यापृ 6 A, परकार्याणि निरूप् 10 or चर्च् 6 P, 10, पराधिकारचर्चां कृ, पराधिकारं प्रविश् 6 P. **2** व्यापृ, व्यापृत-*a* भू. **–er,** *s* पराधिकारचर्चकः, परकार्यनिरूपकः-व्यापारिन् *m.*, अन्यव्यापारचर्चकः. **–ing, –some,** *a.* पराधिकारनिरूपक, परकार्यचर्चाशील; better by (*v.*). –*s.*, **–someness,** *s.* परकार्यचर्चा, पराधिकारनिरूपणं-प्रवेशः, अन्यव्यापारेषु व्यापारः, अन्याधिकारचर्चा-नियोगः-निरूपणं.

Medial, *a.* मध्य, *See* **Intermediate.**

Mediate, *v. i.* माध्यस्थ्यं कृ 8 U, मध्यस्थः भू 1 P, मध्ये वृत् 1 A or गम् 1 P, माध्यस्थ्येन सं-धा 3 U. –*a.* व्यवहित, मध्यवर्तिन्, मध्यस्थ, मध्यस्थित, अंतर्गत. **–ion,** *s.* माध्यस्थ्यं, मध्यस्थता. **–ly,** *adv.* माध्यस्थ्येन, अन्यद्वारेण-द्वारा. **–or,** *s.* मध्यस्थः, मध्यमपुरुषः, मध्यस्थितः. **–orship,** *s.* मध्यस्थाधिकारः, माध्यस्थ्यं.

Medicable, *a.* चिकित्स्य, उपक्रम्य, साध्य, उपचारसाध्य.

Medical, *a.* वैद्य (द्यी *f.*), औषधीय, वैद्यक-आयुर्वेद-संबंधिन्, वैद्यकविषय; 'm. science' आयुर्वेदः, वैद्यशास्त्रं; 'm. treatment' वैद्य-भेषज-उपचारः, औषध-भेषज-प्रयोगः; 'm. man' वैद्यः, भिषक्, चिकित्सकः. **–ly,** *adv.* वैद्यशास्त्रानुरूपं.

Medicament, *s.* **Medicine.** q. v.

Medicaster, *s.* छद्मवैद्यः, कूटचिकित्सकः.

Medicate, *v. t.* औषधैः मिश्र् 10 or संसृज् 6 P, औषधगुणान् दा 3 U or संक्रम् c. **2** औषधं दा; *See* **Cure.** **–ion,** *s.* औषधीयद्रव्यसंसर्गः-मिश्रणं.

Medicine, *s.* औषधं, भेषजं, अगदः, भैषज्यं, जायुः; 'administering of m.' औषधोपचारः, औषधोपक्रमः, भेषजप्रयोगः, चिकित्सा, रुक्प्रतिक्रिया, उपक्रमः, उपचारः, उपचर्या, वैद्यक्रिया-उपचारः-उपक्रमः. **2** (Science) आयुर्वेदः, वैद्यकं, वैद्यशास्त्रं. **–al,** *a.* औषधीय, भेषज (जी *f.*), रोगघ्न (घ्नी *f.*), रोगहर, रोगहारिन्. **2** औषधविषयक.

Medieval, *a.* मध्यमकालीन.

Mediocre, *a.* सामान्य, मध्यम, साधारण (णी *f.*), मध्यम or सामान्य-गुण or भाव. –*s.* सामान्यगुणः नरः. **–Mediocrity,** *s.* सामान्याः, मध्यमाः (pl.) **2** मध्यमता, सामान्यता, मध्यम or सामान्य-भावः or दशा.

Meditate, *v.* ध्यै 1 P, चिंत् 10, भू c., विमृश् 6 P, मनसा-विचर् c. or क्लृप् c. or वि-भू c., समा-धा 3 U, वितर्क् 10. **2** परि-सं-क्लृप् c., चिंत्, युज् 7 U, 10, मंत्र् 10 A; *See* **Intend.** **–ion,** *s.* ध्यानं, चिंता, विमर्शः, भावनं-ना, कल्पनं; (deep) अंतर्ध्यानं, समाधिः, आत्मैकाग्रता, प्रणिधानं, प्रसंख्यानं, (हरः प्रसंख्यानपरो बभूव K. III. 40); 'religious m.' योगः, समाधिः, समाधियोगः, &c.; 'deeply absorbed in m.' ध्यानपर-मग्न-निष्ठ, समाधिस्थ. **–ive,** *a.* चिंता-ध्यान-पर, चिंता-ध्यान-शील, समाधिस्थ, समाहित, सचिंत; 'by means of m. power' समाधियोगेन, प्रणिधानबलेन-योगात्, प्रणिधानतः.

Mediterranean *a.* भूमध्यस्थ, भूवेष्टित मध्यदेशीय, मध्यदेशस्थ.

Medium, *s.* साधनं, द्वारं, द्वार् *f.* कारणं, निमित्तं, हेतुः,करणं,अंगं, योगः,मार्गः, 'through the m. of my friend ' मन्मित्रद्वारेण-द्वारा; 'through the m. of air ' आकाशमार्गेण. 2 मध्यमता, सामान्य-मध्य-पक्ष.

Medley, *s.* संकरः, सन्निपातः, प्र-स-कीर्णकं, द्रव्यसंकुलं, नानाद्रव्यसंमिश्रणं-समूहः. **-a.** सं-प्र-कीर्ण, संकुल, संमिश्रित, संकरीकृत.

Medulla, *s.* मज्जा, मेदस् *n.* **-ry,** *a.* मज्जासंबंधिन्; मेदोमय (यी *f.*)

Meed, *s.* पारितोषिकं, प्रतिफलं.

Meek, *a.* विनीत, सविनय, नम्र-शील-वृत्ति, अनुद्धत, अगर्व, निरहंकार, सौम्य; *See* **Humble. 2** दीन, कृपण. **-ly,** *adv.* सविनयं, नम्रतया, अनुद्धतं, नम्रचेतसा. 2 दीनवत् कृपणं. **-ness,** *s.* विनयः, सौम्यता, अगर्वः, अनौद्धत्यं, नम्रशीलता, दैन्यं, कार्पण्यं.

Meet, *v. t.* सं-इ 2 P, संगम् 1 A, आ-समासद् c., संमिल् 6 P, समा-उपा-गम् 1 P; oft. ex. by दृश् 1 P, नयनपथं-विषयं &c. या 2 P or गम्, प्रति-सं- अभि-मुखं या or गम् or प्राप् 5 P, अभि-सं-मुखीभू 1 P; 'I met a little cottage girl ' उटजनिवासिनी काचिद्बालिका मम नयनविषयं याता or मया दृष्टा; 'they two met each other ' परस्पराभिमुखं प्राप्तौ. **2** (with) आ-सद् c., अधि-गम्, प्राप्, लभ् 1 A, अभि-या-इ-गम्; *See* **Find, Get;** 'm. with calamities ' संप्राप्नुवंति आपदः; 'm. s with death ' मृत्युमभ्येति, निधनं याति, मरणमाप्नोति, विनाशं गच्छति &c.; 'not easy to m. with ' दुर्लभ, दुष्प्राप, दुरासद, &c., 'go out to m. ' प्रत्युद्-या-व्रज-गम्-इ; 'to rise to m. ' प्रत्युत्था 1 P, अभ्युत्था. **-v. i.** संमिल्, सम्-इ, सन्नि-पत् 1 P, एकीभू, एकत्र मिल्; *See* **Assemble. 2** (In battle) संयुध् 4 A, युद्धार्थं मिल्, युद्धं आरभ् 1 A, रणे अभि-युज् pass ; ' the waters m. ' आपः संप्लवंते, संगच्छंते, संभिद्यंते. **-a.** उक्त, उचित, योग्य, उपपन्न. *See* **Proper. -ly,** *adv.* योग्य, उपपन्नं. **-ness,** *s.* औचित्यं, युक्तता. **-ing,** *s.* समागमः; संगति *f.*, संगः, संगमः, संमिलनं. संयोगः. **2** सभा, समाजः, मेला, मेलकः, सदस् *f. n.*, संसद् *f.*, परिषद् *f.*, लोक-जन-समूहः-संघः-समुदायः; गोष्ठी, आस्थानं-नी (m -house); 'member of a m. ' सभ्यः, सदस्यः, सभासद्. **3** संभेदः व्यतिकरः, संगः-गमः.

Megalomania, *s.* अहं-भावः-कृति *f.*-मन्यता.

Megrim, *s.* शिरोवेदना, अर्धावभेदकं. **2** **Humour,** q. v.

Melancholy, *a.* विषण्ण, सविषाद, अवसन्न, खिन्न, उद्विग्न, दुर्मनस्, विमनस्, दीनमनस्क, चिंताशील, चिंताकुल; *See* **Dejected. 2** सदा-नित्य-विषण्ण, खेदवृत्ति, विषादशील. **3** विषादात्मक, खेद-शोक-गर्भ; ' to be m. ' अव-वि-सद् 1 P, ग्लै 1 P, खिद् pass **-s.** विषादः, अवसादः, खेदः, उद्वेगः, ग्लानि *f.*, निर्वेदः, दैन्यं, चित्तोद्वेगः, वैमनस्यं, विषादवृत्ति *f.* **-ic,** *a.* सदाविषादिन्. **-ily,** *adv.* सविषादं, सोद्वेगं, &c.

Melee, *s.* रणसंकुलं, संकुलसंग्रामः.

Meliorate, *v. See* **Improve.**

Melliferous, *a.* मधुप्रद, मधुदायिन्.

Mellifluous, Mellifluent, *a.* मधुर, मधुमय (यी *f.*), मधुस्यंदिन्-स्राविन्. **2** मधुराक्षर, मधुरवाच्. **-ly,** *adv.* मधुरं. **-ness,** *s.* माधुर्यं, मधुप्रवाहः-स्रावः.

Mellow, *a.* पक्व, परिणत, पाकमृदु. **2** मृदु, कोमल, स्निग्ध, सुखस्पर्श; ' m. to the ear ' मंजुल, मंजुस्वन, मधुर-कोमल-शब्द. **-v. i.** पच् pass., पक्वदशां या 2 P or प्राप् 5 P, मृदूभू 1 P. **-v. t.** पच् 1 P or c., मृदूकृ U: *See* **Mature. -ness.** *s.* पक्वता, परिपाकः, पक्वदशा, कोमलता, मार्दवं.

Melody, *s.* सुस्वरः, स्वरमाधुर्यं, कलता, माधुर्यं, सुश्राव्यता, श्रोत्राभिरामता, सुखश्रवता, स्वरानुपूर्व्यं, तालैक्यं; ' m. of song ' गीतरागः. **-Melodious,** *a.* मधुर, सुखश्रव, सुश्राव्य, श्रुतिमनोहर, सुस्वर, सुस्वन, मंजुल, कल, श्रोत्राभिराम, श्रुति-श्रोत्र-सुख, मंजु-कल-स्वन, मधुरस्वर, मधुराक्षर. **-ly,** *adv.* मधुरं, कलं, सुस्वरेण. **-ness,** *s.* माधुर्यं, कलता, &c.

Melon, *a.* स्फुटिफलं, तरंबुजं, कालिंगं, मेढुः.

Melt, *v. i.* वि ली 9 P, 4 A, वि-,द्रु 1 P (fig. also), गल् 1 P, क्षर् 1 P, द्रवीआर्द्री-भू 1 P. **2** दयार्द्रीभू, करुणया द्रु; 'his whole soul m s with benevolence ' अस्य सर्वात्मनि परहितबुद्धिर्निषक्तेव, परोपकारपरवशः. **-v. t.** वि-ली c., वि-,द्रु c., गल् c. **2** दयार्द्रीकृ 8 U, करुणार्द्रीकृ, वत्सलयति (D.); 'to be m. ed ' आर्द्रीभू, आर्द्र-*a.* भू, द्रु, अभि-स्यंद् 1 A; ' his heart was m. ed with affection ' तस्य हृदयं स्नेहार्द्रीभूतं, स्नेहेनाभ्यस्यंदत. **-er,** *s.* द्रावकः, विलयनकृत्, *m.* **-ing,** *s.* द्रवः, द्रवणं, विलयनं, गलनं, क्षरणं. **2** द्रावणं, विलायनं.

Member, *s.* अंगं, अवयवः, गात्रं, प्रतीकः, अपघनः; ' Veda with all its m s ' सांगः वेदः. **2** (Of a discourse &c.) अंगं, प्रकरणं, खंडः-डं, देशः, परिच्छेदः, विभागः, अंशः; ' m. by m. ' अवयवशः, भागशः; ' becoming a m. ' अंगभूत. **3** (Of an assembly &c.) सभ्यः, सभासद्, सदस्यः, पारिषद्यः, सभाभ्यंतरः, सामाजिकः; ' m. of an association ' गणाभ्यंतरः. **4** (Of a family) कुलावयवः, कुटुंबिन् *m.*: m. of a con-

pound' पदं. **-ed,** *a.* अंगिन्, अवयविन्, अंग in comp. **-ship,** *s.* सभ्यपदं.

Membrane, *s.* त्वच् *f.*, तनुत्वक्, आवरणत्वक्, चर्मन् *n.* **-ous,** *a.* तनुत्वगावृत.

Memento, *s.* स्मरणं, स्मारकं.

Memoir, *s.* वृत्तं, चरित्रं, वृत्तांतः, इतिहासः; चरित्र-रचना-लिखनं.

Memory, *s.* स्मृति *f.*, स्मरणशक्ति *f.*, धारणा, स्मरणं, संस्मृति *f.*, संस्मरणं. **2** स्मार्तकालः, स्मृतिकालः; 'retentive m.' मेधा, धारणा, धारणावती धीः; 'having retentive m.' मेधाविन्, धारणावत्; 'commit to m.' कंठस्थ-*a.* कृ 8 U, हृदये-मनसि-चित्ते-कृ, अभ्यस् 4 U; 'committed to m.' कंठस्थ, हृदयस्थ; 'store in m.' हृदये नि-उप-धा 3 U or कृ, अवधृ 10; 'to remain only in m.' स्मृति-विषयतां-स्मृतिपथं-स्मर्तव्यशेषं-कथावशेषं-गम् 1 P or प्राप् 5 P; 'loss of m.' स्मृतिलोपः; 'time beyond m.' अस्मार्तकालः; 'within m.' स्मार्ते काले. **-able,** *a.* स्मर्तव्य, स्मरणार्ह; प्र-वि-ख्यात, प्रसिद्ध, सुविज्ञात. **-Memorandum,** *s.* स्मरणलेखः-पत्रं, स्मारकं पत्रं. **-Memorial,** *s.* स्मरणचिह्नं, स्मारकं, स्मारकं कृत्यं, स्मारकविषयः. **2** आवेदनपत्रं, अभ्यर्थनालेखः, विज्ञप्ति *f.*, विज्ञापनापत्रं. **-a.** स्मारक, अनुबोधक, स्मृतिकर (री *f.*). **-ist,** *s.* प्रार्थकः, अर्थिन् *m.*, प्रार्थयितृ *m.*, विज्ञप्तिकृत् *m.* **-ize,** *v. t.* वि-ज्ञा c. (ज्ञापयति), निवेदनपत्रेण प्रार्थ् 10 A.

Menace, *v. t.* तर्ज् 1 P, 10 A, भी c., भर्त्स् 10 A, भयं दृश् c.; *See* **Frighten.** **-s.** तर्जनं-ना, विभीषिका, भर्त्सनं-ना, भयदर्शनं, अपकारगिर् *f.* **-er,** *s.* भर्त्सनकृत् *m.*, तर्जकः. **-ing,** *a.* भीषण, भयप्रद.

Menagerie, *s.* वि(वी)तंसः; पशुपक्षिसंग्रहः.

Mend, *v. t.* नवीकृ 8 U, सं-धा 3 U, समाधा-प्रतिसमा-धा, उद्धृ 1 P, (जीर्णं) सं-धा or साध् c. **2** शुध् c., प्रतिकृ; प्रमृज् 2 P or c. **3** प्रवृध् c., उत्कृष् 1 P, भद्रतरीकृ; *See* **Improve;** 'm. your pace' लघु लघु गच्छ. **-v. i.** वृद्धिं-उत्कर्षं-उन्नतिं-इ-या 2 P or गम् 1 P, भद्रतरीभू, सुस्थ-*a.* भू, वृध् 1 A. **-er,** *s.* संधातृ *m.*, उद्धर्तृ *m.* **-ing,** *s.* संधानं, समाधानं, उद्धारः, प्रतिकरणं.

Mendacious,-city, *See* **Liar, Lying,** under **Lie.**

Mendicant, *s.* भिक्षुः, भिक्षुकः, अर्थिन् *m.*, याचकः, भिक्षार्थिन् *m.*, भिक्षाशिन् *m.*, भैक्ष्यभुज् *m.*, वनीयकः, याचनकः, मार्गणः. **2** (Religious) परिव्राज् *m.*, परिव्राजकः, यतिन् *m.*, यतिः, संन्यासिन् *m.* **-Mendicancy, -Mendicity,** *s.* भैक्ष्यं, भिक्षा, भिक्षाशित्वं, भिक्षावृत्ति *f.*, भैक्ष्याजीवः, याचना, याच्ञा, याचकवृत्तिः, प्रव्रज्या.

Menial, *s.* भृत्यः, प्रेष्यः, दासजनः, चेटः-टी, गृहदासः-सी, किंकरः, अपकृष्टः; परिजनः, दासवर्गः, भृत्यवर्गः (m. s). **-a.** (*s.*) in comp.; व्रातीन, अपकृष्ट; *See* **Mean;** 'm. duties' दासकर्मन्; व्रात्यं, नीचकर्म.

Meniscus, *s.* अर्धचंद्राकारः काचः.

Menology, *s.* मासपंजिका.

Menses, *s.* ऋतुः, आर्तवं, पुष्पं, रजस् *n.*, कला; 'first appearance of m.' रजोदर्शनं.

Menstrual, *a.* मासिक (की *f.*), मास्य, मासीय, मासिमासिक; 'm. time' ऋतुः, ऋतुकालः; 'm. discharge' रजस् *n.*, पुष्पं, ऋतुः. **-Menstruate,** *v. i.* रजस्वला-ऋतुमती-भू 1 P. **-ion,** *s.* ऋतुस्रावः. **-Menstruous,** *a.* आर्तव (वी *f.*), ऋतु in comp. **2** रजस्वला, ऋतुमती, पुष्पवती, स्त्रीधर्मिणी, अविः, आत्रेयी; मलिनी, उदक्या, अस्पर्शा.

Menstruum, *s.* द्रावणं, विद्रावकरसः.

Mensurable, *a.* प्रमेय, माप्य.

Mensurate. *v. t.* मा 3 A, 2 P; *See* **Measure.** **-ion,** *s.* प्र-परि-माणं, मापनं, मिति *f.*

Mental, *a.* मानसिक (की *f.*), मानस (सी *f.*), मनःस्थ, चित्तगत, चित्तज, मनोभव; gen. by मनस् or चित्त in comp.; 'm. distress' मनस्तापः. **-ly,** *adv.* मनसा, बुद्ध्या.

Mention, *v. t.* कथ् 10, आ-ख्या 2 P, नि-आ-विद् c., शंस् 1 P, अभि-धा 3 U, उदीर् c., उच्चर् c., कृत् 10, वच् 2 P, निर्दिश् 6 P; स्मृ 1 P, (as precepts); 'will be m. ed further on' अग्रतो वक्ष्यते; 'm. by name' नाम ग्रह् 9 U; 'not to m.' ex. by का कथा, का गणना (with loc.), आस्तां-तिष्ठतु-आसतां, followed by अपि; 'not to m. embodied beings (heated by affliction) even red-hot iron softens down (after a time)' अभितप्तमयोपि मार्दवं भजते कैव कथा शरीरिषु (R. VIII. 43); का वा गणना सचेतनेषु अपगतचेतनान्यपि संघट्टयितुमलं मदनः. (Ka. 157); तिष्ठन्तु तावत्सेवापरा राजानः प्रजा अपि पृष्ठतो लगन्ति (Ka. 260). **-s.** अभिधानं, कथनं, आख्यानं, आ-नि-वेदनं, उच्चारणं, कीर्तनं, निर्देशः; नामग्रहणं-निर्देशः. **-ed,** *a.* कथित, उक्त, निर्दिष्ट, कीर्तित, स्मृत, &c.; 'above-m.' प्रागुक्त; 'about to be m.' वक्ष्यमाण.

Mentor, *s.* उपदेशकः, उपदेष्टृ *m.*

Mephitic,-al, *a.* पूतिगंधि, दुर्गंधमय (यी *f.*), प्राणहर, मारात्मक, जीवितापह.

Mercantile, *See* under **Merchant.**

Mercenary, *a.* अर्थपरवश, लाभपरायण, लाभार्थिन्, धनलुब्ध, लाभबुद्धि-बुद्धि, स्वार्थपर

स्वार्थापेक्षक; 'from m. motives' लाभदृष्ट्या, लाभेच्छया, स्वार्थापेक्षया. 2 भृतक, वैतनिक (की f.), भृति-भरण्य-भुज्, वेतनार्थिन्. -s भृतकः, भृति-भरण्य-भुज् m., वैतनिकः, वेतनार्थिन् m. -ly, adv. लाभदृष्ट्या, लाभापेक्षया, भृतकवत्, स्वार्थबुद्ध्या. -ness, s. लाभदृष्टि f -अपेक्षा-बुद्धि f., धनलाभलोभः, स्वार्थ-वेतन-अपेक्षा.

Mercer, s. कौशेयोर्णवस्त्रवणिज् m. -y. s. कौशेयवस्त्रव्यवहारः.

Merchant, s. वणिज् m., वाणिजः, आपणिकः, नैगमः, सार्थवाहः, पण्याजीवः, क्रयविक्रयिकः, वैदेहकः, सार्थिकः, व्यवहारिन् m., वाणिज्योपजीविन् m. श्रेष्ठिन् m.; 'm.'s business, वाणिज्यं, वणिक्क्रिया; 'm.'s exchange' श्रेष्ठिचत्वरं; 'voyaging or seafaring m.' सांयात्रिकः, पोतवणिज्; 'company of m.s' सार्थः, निगमः. -able, a. पण्य, पण्यार्ह. -Merchandise s. वाणिज्य, व्यवहारः, क्रयविक्रयौ (du.) 2 पण्यं, भांडानि, पण्यद्रव्याणि, वाणिजद्रव्यं-भांडं-पण्यं. -Mercantile, a वाणिज (जी f.), वाणिज्यिक (की f.), वाणिज्यसंबंधिन्.

Mercury, s पारदः, चपलः, रसः, सूतः, पारतः; 'white sublimate of m.' रसकर्पूरः; 'sulphuret of m.' कज्जली 2 बुधः, रौहिणेयः, सौम्यः. -al, a. पारदात्मक, पारदमय (यी f.), सपारद. 2 चपल, लघुशरीर, सोत्साह, तेजस्विन्. 3 द्रव्यपरायण, धूर्त.

Mercy, s. दया, कृपा, करुणा, अनुकंपा, अनुक्रोशः, कारुण्यं, घृणा, दया, कृपाशीलता, दयालुता. क्षमाशीलता, दया-कृपा-बुद्धि f. 2 प्रसादः, अनुग्रहः. 3 क्षमा तितिक्षा 'fountain of m.' करुणाकरः, दयासागरः; दयानिधिः; 'an object of m.' कृपापात्रं-भाजनं, अनुकंप्य, अनुग्राह्य, तपस्विन्; 'to show m.' दय् 1 A (with gen.), अनुकंप् 1 A (with acc.), दयां कृ 8 U (with loc.); 'm., Oh king' क्षमस्व राजन्. -ful, a. दयालु, कृपालु, कृपा-दया-करुणा-शील, करुणार्द्र, दयार्द्र, अनुकंपिन्, सदय, सकरुण, सानुक्रोश, क्षमाशील; वत्सल, दयाबुद्धि-दृष्टि; See Kind. -fully, adv. सदयं, सकरुणं, सानुकंपं, दयया, करुणया, सानुक्रोशं. -fulness, s. दया, कृपा, घृणा, दयाशीलता, अनुकंपा, वात्सल्यं; See (s.). -less, a. निर्दय, निष्करुण, निर्घृण, अकरुण, कठोर, निष्कृप, निष्ठुर, नृशंस. -lessly, adv. निर्दयं, निष्कृपं, निर्घृणं, निष्ठुरं.

Mere, a. केवल, शुद्ध; gen. ex. by एव, or मात्र in comp.; 'by m. touch' स्पर्शमात्रेण; 'a m. fool' मूर्ख एव, केवलमूर्खः. -s. सरस् n., ह्रदः; See Lake. 2 पर्यंतः, सीमा; See Boundary. -ly adv. केवलं, एव, मात्र in comp; 'by m. advising' उपदेशमात्रात्, उपदेशादेव, &c

Meretricious, a. कृत्रिमशोभामय (यी f.), बाह्यरुचिर, कृत्रिमरागवत्, मिथ्याशोभन. 2 पण्यांगनीय, वेश्यासंबंधिन्. -ly, adv. मिथ्याशोभया.

Merge, v. i. नि-,मस्ज् 6 P, अव-गाह् 1 A (lit); निपा-ग्रस्-pass., प्र-वि-ली 4 A, विलुप् pass., नश् 4 P, (fig.); 'one fault m.s in a collection of good qualities' एको हि दोषो गुणसंनिपाते निमज्जति (K. 1. 3). -v. t. मस्ज् c., (मज्जयति), अवगाह् c. 2 नश् c., वि-लुप् 6 P or c., ग्रस् 1 A, नि-पा 1 P, प्र-वि-ली c. -Mersion, s. मज्जनं, अवगाहः-हनं.

Meridian, s मध्याह्नः, दिनमध्यं, मध्याह्नकालः-समयः. 2 खमध्यं; 'distance from the first m.' रेखांतरं; 'the sun is on the m.' नभसो मध्यमलंकरोति भानुः 3 परा कोटिः-काष्ठा, उत्कर्षः. -a. माध्याह्निक (की f.). 2 खमध्यसंबंधिन्. 3 उत्तम, परम; oft ex, by परा कोटिः, परा काष्ठा.

Meridional, a. दक्षिणदेशीय; दाक्षिणाभिमुख (खी f.).

Merit, s. गुणः, योग्यता, पात्रता, उत्कर्षः, श्रेष्ठता, विशिष्टता, विशेषः, गुणोत्कर्षः, गुणवत्ता. 2 (M. s) गुणागुणौ, गुणदोषौ, धर्माधर्मौ. 3 पुण्यं, धर्मः, सुकृतं, श्रेयस् n., वृषः; 'acquired by m.' पुण्यार्जित; 'efficacy of m.' पुण्यप्रतापः-प्रभावः; 'one possessing many m. s' पुण्यनिधिः-राशिः-सागरः, पुण्यात्मा. -v. t. अर्ह् 1 P, अर्ह-योग्य-in comp.; See Deserve; 'm. ing censure' निंद्य, गर्हणीय, निंदापात्रं. -ed, a. युक्त, उचित, योग्य; See Proper. -Meritorious, a. प्रशस्य, श्लाघ्य, प्रशस्त, श्लाघार्ह, प्रशंसार्ह. 2 गुणिन्, गुणवत्, गुणसंपन्न, गुणोपेत, गुणान्वित. 3 पुण्यवत्, पुण्यशील, पुण्यात्मन्, पुण्यात्मक, पुण्यशालिन्; पुण्य, पुण्यरूप, अवदात (deed): 'a m. deed' पुण्यं, धर्मः, सुकृतं, अवदातं कर्म. -ly, adv. श्लाघ्यतया, प्रशस्तं. -ness, s. गुणवत्ता, पात्रता, योग्यता, &c.

Mermaid, s. मत्स्यांगना, मत्स्यस्त्री.

Merry, a. प्र-हृष्ट, सानंद, सोल्लास, प्रोत्फुल्ल. प्रमुदित, प्रहृष्टचित्त; आनंद-उल्लास-हास्यवृत्ति, प्रसन्नवदन, विलासिन्, विनोदिन्, परिहासशील. 2 हास्यकर (री f.), विनोदक; 'to make m.' उत्सवं कृ 8 U; 'to be m.' उल्लस् 1 P, मुद् 1 A; See Delight. 'm.-andrew' भंडः, वैहासिकः, विदूषकः. 'm. making' आनंदोत्सवः, उत्सवकरणं. -ly, adv. सहर्षं, सोल्लासं, सानंदं, हृष्टमनसा, -ment, s. प्र-हर्षः, उल्लासः, प्र-मोदः, आनंदः, आह्लादः, हास्यं, परिहासः, उत्सवः, कौतु विलासः, विनोदः; लीला, खेला;

'what is said in m.' हास्यावेक्षोक्तिः; नर्मालापः, विनोदोक्ति *f.* –ness, *s.* द्रवता, सानंदता, आर्नद्रवृत्ति *f.*

Meru, *s.* मेरुः, सुमेरुः, हेमाद्रिः, रत्नसानुः, सुरालयः.

Mesentery, *s.* अंत्रपेशी.

Mesh, *s.* जालरंध्र-छिद्रं-अंतरं. –*v. t.* जाले पत् c. or बंध् 9 P. –y, *a.* जालरूप, जालाकार.

Meslin, *s.* मिश्रधान्यं, धान्यमिश्रणं. –*a.* मिश्रधान्यकृत.

Mess, *s.* अन्नं, अन्नपात्रं. 2 गणान्नं, सहभोजनं; सहभोजिनः, पंक्तिभोजिनः (pl.): सहभोजिपंक्ति *f.* गणः, गणान्नपंक्तिः. 3 संकरः, प्र-सं-कीर्णकं, सन्निपातः, संमिश्रणं, संकुलं; 'm.-mate' सह-पंक्ति-भोजिन् *m.* –*v. i.* सह-एकत्र-भुज् 7 A or अश् 9 P, पंक्तिभोजनं कृ 8 U. –*v. t.* संमिश्र् 10, संकृ 6 P.

Message, *s.* संदेशः, वाचिकं, संदेशवाच् *f.*, वार्ता, शासनं; 'bearing a m.' दौत्यं, दूत्यं, प्रेष्यभावः; 'sending on a m.' प्रतिशासनं. –***Messenger***, *s.* दूतः, संदेश-वार्ता-हरः, वार्तायनः, आ-ख्यापकः, निसृष्टार्थः, प्रेष्यः; वैवधिकः; 'female m.' दूति-ती-तिका; 'who will go as a m.' कः प्रयास्यति दौत्येन.

Messuage, *s.* वासगृहं, गृहवाटिका.

Metacarpus, *s.* करभः, पीलुः.

Metachronism, *s.* न्यूनकालनिरूपणं.

Metal, *s.* धातुः, लोहः-हं, तैजसं; 'base m.' कुप्यं; 'fused m.' रसधातुः, धातुरसः 'inferior m.' उपधातुः. –lic, –lical, *a.* धातुसंबंधिन्. 2 धातुमय (यी *f.*), धातुरूप, लोह (ही *f.*), धातु-लोह- in comp. –list, *s.* धातुज्ञः, धातुकर्मकारः. –***Metalliferous***, *a.* धातुमद्. –***Metalliform***, *a.* धातुसदृश (शी *f.*). –***Metallography***, *s.* धातुशास्त्र-विद्या. –***Metallurgy***, *s.* धातुशोधनं.

Metamorphose, *v. t.* रूपं परिणम् c. or परिवृत् c., रूपांतरं दा 3 U or ग्रह् c.; *See* **Change**. –ed, *a.* परिणतरूप-शरीर-आकार. –***Metamorphosis***, *s.* रूपपरिणामः-परिवृत्ति *f.*-भेदः, रूपांतरं, रूप-शरीर-विकारः.

Metaphor, *s.* रूपकं, लक्षणा, आरोपः, उपचारः. 2 दृष्टांतः, निदर्शनं. –ic, –ical, *a.* औपचारिक-लाक्षणिक (की *f.*), सरूपक, आरोपित; 'm. use' उपचारः. –ically, *adv.* लक्षणया, उपचारेण, सारोपं; 'to use m.' उपचर् 1 P: *See* **Figuratively.**

Metaphysic,-al, *a.* आन्वीक्षिक-आध्यात्मिक (की *f.*), आत्मविषय, आत्मज्ञानपर. –ally, *adv.* आत्मविद्यानुसारेण. –ian, *s.* आन्वीक्षिकीज्ञः. –***Metaphysics***, *s.* आन्वीक्षिकी, आत्म-अध्यात्म-विद्या, आत्मविषयकं ज्ञानं, आत्मतत्त्वविद्या-शास्त्रं.

Metastasis, *s.* रोगस्थलांतरं

Metatarsus, *s.* प्रपदं.

Metathesis, *s.* अक्षर-वर्ण-विपर्यासः-व्यत्यासः-व्यत्ययः.

Mete, *v. t.* परि-,मा 3 A, 2 P; *See* **Measure.**

Metempsychosis, *s.* पुनर्जन्मन् *n.*, अन्यजन्म, जन्मांतरं, देहांतरप्राप्ति *f.*

Meteor, *s.* उल्का, उत्पातः. –ic, *a.* उल्कोद्भव, उल्कोत्पन्न. –ous, *a.* उल्काधर्मक. –***Meteorology***, *s.* अंतरीक्षविद्या, वायुनभो-विद्या.

Meter, *s.* मापकः.

Methinks, *v. imp.* मन्ये, तर्कयामि, शंके; ध्रुवं.

Method, *s.* रीति *f.*, प्रकारः, मार्गः, विधा, विधिः; पद्धति *f.*; *See* **Manner.** 2 व्यवस्था, क्रमः, अनुक्रमः, पर्यायः, आनुपूर्वी-र्व्यं, परिपाटि-टी *f.*, आवृत् *f.*, परंपरा; व्यवस्थया रचनं-ना, व्यूहनं, विन्यासः, संविधानं, क्रमेण स्थापनं, नियमः. –ical, *a.* व्यवस्थित, यथाक्रम, सक्रम, अनुपूर्व, सूत्रित, यथापर्याय. 2 (Of persons) क्रमानुसारिन्, क्रमानुगत, क्रम-नियम-शील. –ically, *adv.* यथाक्रमं, अनुपूर्वशः, आनुपूर्व्येण, क्रमेण, क्रमशः, पर्यायेण, अनुक्रमेण, यथानियमं. –icalness, *s.* व्यवस्था, क्रमशीलता, &c. –ism, *s.* नियमनिष्ठा. –ist, *s.* नियम-कर्म-निष्ठः. –ize, *v. t.* व्यव-स्था c. (स्थापयति), क्रमेण स्था c. or वि-धा 3 U or विरच् 10 or विन्यस् 4 U.

Meticulous, *a.* साशंक. 2 अतिसावधान, अत्यवहित.

Metre, *s.* छंदस् *n.*, वृत्तं. –***Metrical***, *a.* छंदोबद्ध, वृत्तात्मक, छांदस (सी *f.*), छंदोरूप, पद्यरूप, पद्यात्मक.

Metronome, *s.* तालमापनी.

Metropolis, *s.* राजधानी. –***Metropolitan***, *a.* राजधानीय.

Mettle, *s.* तेजस् *n.*, सत्त्वं, उत्साहः, वीर्यं, ओजस् *n.*, प्रभावः, पौरुषं, ऊर्जस् *n.* –ed, -some, 'of great m.' 'high-m. ed' *a.* तेजस्विन्, महा-उरु-सत्त्व, परमोत्साह, ओजस्विन्, वीर्यवत्, सपौरुष.

Mew, *s.* पंजरं, वीतंसः. 2 बंधनं, निरोधः, बंधनागारं, गुप्ति *f.* –*v. t.* पंजरे निरुध् 7 U or बंध् 9 P. –*v. i.* पक्षान् पत् c. or मुच् c.

Mewl, *v. i.* (शिशुवत्) क्रंद् 1 P, रु 2 P, आक्रुश् 1 P.

Mews, *s.* अश्वकोष्ठं, अश्वशाला.

Miasm,-a, *s.* पूतिबाष्पः, मारात्मकः वायुः.

Mica, *s.* अभ्रकं.

Mickle, *a.* बहु, बहुल.

Microbe, *s.* सूक्ष्मजंतु *m.*

Micro-cosm, *s.* सूक्ष्मं जगत्.

Microscope, *s.* सूक्ष्मदर्शनयंत्र

Micturition, *s.* मूत्रोत्सर्गेच्छा.

Mid, *a.* मध्य, मध्यम, अर्ध, in comp.; 'm., course' अर्धमार्गः, अर्धपथः; 'm.-day'

मध्याह्नः; (*a.*) माध्यंदिन (नी *f.*), माध्याह्निक (की *f.*); 'm.-heaven' खमध्यः; 'm.-land' मध्यदेशीय, देशमध्यवर्तिन्; 'm.-night' मध्यरात्रः, अर्धरात्रः, रात्रिमध्यं, निशीथः; 'm.-summer' निदाघमध्यं; 'm.-way' अर्धपथः-मार्गः; (*adv.*) अर्धमार्गे, मार्गमध्ये; 'm.-wife' सूतिका; साविका, प्रसवकारिणी; 'm.-wifery' प्रसवकार्यकरणं, सूतिकर्मन् *n.*, गर्भमोचनविद्या; 'm.-winter' शिशिरमध्यं. **-*Middle*,** *s.* मध्यं, मध्यभागः-देशः-स्थानं-स्थलं; अभ्यंतरं, गर्भः, अंतरं, in comp.; 'in the m. of the ocean' मध्येसमुद्रं; 'in the m. of the house' गृहाभ्यंतरे, गृहगर्भे; 'going in the m.' मध्यग. **-*a.*** मध्य, मध्यम, मध्यस्थ, मध्यवर्तिन्, मध्यस्थित; 'the m. classes' मध्यमजातीयाः, मध्यमवर्णाः; 'm.-aged' मध्यमवयस्क, गतयौवन; 'm. finger' मध्यमा, कर्णिका; 'm.-man' मध्यस्थः, मध्यमपुरुषः. **-ing,** *a.* मध्य, मध्यम, मध्यपरिमाण. 2 मध्यमपदस्थ, मध्यमगुण, सामान्य, साधारण (णी *f.*). **-Midst,** *s.* मध्यं; *See* **Middle;** 'in the m.' मध्ये; 'from their m.' तेषां मध्यात्; 'in the m. of this talk' एवं वदत्सु; 'in the m. of calamities' विपद्ग्रस्त-*a.*, दुःखमग्न-*a.*

Midden, *s.* अवकरनिकरः.

Mien, *s.* आकारः, रूपं, आकृति *f.*, वदनाकारः, वदनाकृतिः, मुखचर्या; 'with a dejected m.' खिन्न-म्लान-वदन.

Might, *s.* बलं, शक्ति *f.*, सामर्थ्यं, तेजस् *n.*, शौर्यं, वि-परा-क्रमः, प्रभावः; *See* **Strength;** 'with all one's m.' यथाशक्ति, यावच्छक्यं. **-*Mighty*,** *a.* प्रबल, शक्तिमत्, बलवत्, ओजस्विन्, ऊर्जस्वल, विक्रांत, बलिन्; उरुविक्रम; *See* **Strong. 2** महत्, विशाल, प्रतापवत्, महौजस्, विभूतिमत्; 'm. lord' महेश्वरः, अधीश्वरः. **-ily,** *adv.* बलेन, विक्रमेण, शौर्येण. **2** अतीव, अत्यंतं, बलवत्, भृशं, अतिमात्रं. **-iness,** *s.* सामर्थ्यं, प्रभावः, वीर्यं; *See* (*s.*)

Migrate, *v. i.* निर्गम् 1 P, भ्रम् 1, 4 P, देशांतरं-स्थानांतरं-गम् or अधि-वस् 1 P or अध्यास् 2 A. **-ion,** *s.* भ्रमणं, पर्यटनं, देशांतरगमनं. **-ory,** *a.* देशभ्रमण-पर्यटन-शील.

Milch-cow, *s.* क्षीरिणी, पयस्वती, दुग्धवती, पीनोध्नी.

Mild, *a.* मृदु, कोमल, सौम्य, अप्रखर, अचंड, अनुग्र, अपरुष, सुकुमार, शांत, अतीक्ष्ण, अतीव्र. 2 सदय, कृपालु, दयालु, दयार्द्र, क्षमाशील, अतीक्ष्ण, अतीव्र, अतीक्ष्णदंड, मृदुस्वभाव, सौम्यवृत्ति, मृदुभाव, सामोपायिन्; *See* **Innocent** also; 'm. means' सामन् *n.*, सामोपचारः, सामोपायः; 'm. speech' सांत्ववादः, मृदुभाषणं. **-ly,** *adv.* मृदु, कोमलं, अनुग्रं, अपरुषं, अतीव्रं, मार्दवेन, साम्ना, सामोपायेन, सामोपचारैः. **-ness,** *s.* मार्दवं, मृदुता, कोमलता, सौम्यता, अतीक्ष्णता, शांति *f.* **2** प्रकृतिमृदुता, मृदुता, मृदुकोमल-स्वभावः; कृपालुता, सदयता, सौम्यवृत्ति *f.*, दयालुता, कृपाशीलता; क्षमा, साम.

Mile, *s.* अर्धक्रोशः; '3 m. s' सार्धक्रोशः; '4 m. s' क्रोशद्वयं.

Militant, *a.* युद्धप्रवृत्त, रणोद्यत, युद्धोद्युक्त.

Military, *a.* सांग्रामिक-सामरिक-आयुधिक (की *f.*), क्षात्र (त्री *f.*), युद्ध in comp. **2** युद्धप्रवृत्त, योधिन्, शस्त्रोपजीविन्, शस्त्रभृत्, आयुधजीविन्; 'm. preparation' युद्धसामग्री; 'm. profession or life' आयुध-शस्त्र-वृत्ति *f.*, सैनिकवृत्तिः, शस्त्राजीवः; 'm. caste' क्षत्रियजातिः; 'a man of the m. class' क्षत्रः-त्रं, क्षत्रियः, राजन्यः, विराट्, बाहुजः, मूर्धाभिषिक्तः; 'a woman of the m. class' क्षत्रिया-याणी; 'm. man' योधः, वीरः, सैनिकः; 'm. duty' क्षात्रधर्मः, क्षत्रिय-क्षत्र-धर्मः; 'm. science' युद्धशास्त्रं, सांग्रामिकं, शस्त्रास्त्रविद्या, आयुध-रण-विद्या. **-*s.*** सैन्यं, सैनिकवर्गः, क्षत्रगणः.

Militate, *v. i.* वि-प्रति-रुध् 7 U, विरुद्ध-प्रतिकूल-*a.* भू 1 P.

Militia, *s.* देशरक्षिणः, रक्षकयोधाः (pl.).

Milk, *s.* पयस् *n.*, दुग्धं, क्षीरं, स्तन्यं; गोदुग्धं, गोरसः, गव्यं (cow's m.); 'fresh m.' पीयूषः-षं; 'made of m.' पयस्य; 'coagulated m.' दधि, क्षीरजं; 'giving much m.' बहुदुग्धा; 'm. livered' कातर, क्लीबहृदय, भीरु; 'm.-maid' गोपकन्या, आभीरी, गोदोहिनी; गोपी, गोपिका; 'm.-man' दोग्धृ *m.*, दोहकः, गोपः, आभीरः, गोधुक्; 'm.-pail,-pan' दुग्ध or क्षीर-पात्रं-भांडं-भाजनं; दोहनी; 'm.-porridge' क्षैरेयी; 'm.-sop' कापुरुषः, भीरुः; 'm.-woman' गोपी, आभीरी, दोहिनी. **-*v. t.*** दुह् 2 U (with two acc.), दुग्धं निष्कृष् 1 P or दुह् c. **-er,** *s.* दोग्धृ *m.* दोहकः, दुह् *m.* **-y,** *s.* क्षीरिन्, पयस्य, पायस (सी *f.*); (*s.*) in comp.; 'm. ocean' क्षीर-दुग्ध-सागरः. **2** क्षीरोपम, दुग्धतुल्य **3** क्षीरद, दुग्धप्रद, बहुदुग्ध; 'm. way' वियद्गंगा; *See* **Galaxy. 4** भीरु कातर, सौम्य; *See* **Mild.**

Mill, *s.* चक्रं, पेषणी, पेषणयंत्रं-चक्रं. **-*v. t.*** पिष् 7 P, चूर्ण् 10. **2** मुष्टिना तड् 10 or प्रहृ 1 P. **-er,** *s.* पेषकः, पेषणोपजीविन् *m.*

Millennium, Millenary, *s.* सहस्रवर्षं, सहस्रसंवत्सरं. **-*Millennial,* -*Millenarian*,** *a.* सहस्रवर्षीय-ण, सहस्रवार्षिक (की *f.*).

Millesimal, *a.* सहस्रतम (मी *f.*), सहस्रांशात्मक.

Millet, *s.* अणुः, प्रियंगुः.

Milliner, *s.* स्त्रीवस्त्रकृत्, स्त्रीवसनकारिणी. **-y,** *s.* स्त्रीपरिच्छदः-सज्जा, स्त्रीवस्त्रसामग्री.

Million, *s.* नियुतं, दशलक्षं; 'ten m.' कोटि *f.*; 'hundred m.' अर्बुदः. **-ary,** *a.* नियुतीय. **-th,** *a.* नियुततम (मी *f.*). **-Millionaire,** *s.* कोटीश्वरः, लक्षाधीशः.

Milt, *s. See* **Spleen.**

Mime, *s.* नटः, नर्तकः, कुशीलवः, चारणः, रंगाजीवः. 2 भंडः, विदूषकः, वैहासिकः. **-Mimic,** (**-al**), *a.* अनुकरण-शील-स्वभाव, अनुकारिन्, विडंबनकारिन्. 2 विडंबन-अनुकरण-रूप. **-s.** भंडः, वैहासिकः, विदूषकः. 2 अनुकारिन् *m.* **-v.** *t.* (उपहासपूर्वं) अनुकृ 8 U, विडंब् 10. **-ker,** *s.* अनुकारिन् *m.*, विडंबनकृत्. **-ry,** *s.* सोपहासं अनुकरणं or विडंबनं; अनुकारः, विडंबनं.

Mimosa, *s.* नमस्कारी, गंडकारी-ली, समंगा, खदिरा, लज्जालुः.

Minaret, *s.* शिखरं, शृंगं प्रासाद-भवन-शिखरं.

Minatory, *a.* तर्जक, भयंकर, भीषण.

Mince, *v. t.* खंडशः-सूक्ष्मलवशः-कृत् 6 P or छिद् 7 P or खंड 10, शकलीकृ 8 U; 'do not m. matters' यथावृत्तं सर्वं साकल्येन निवेदय, सर्वं संपूर्णं प्रकाशय; 'm. ed meat' छिन्नमांसं. **-v.** *i.* ललितगत्या चल्-र् 1 P or गम् 1 P, भिन्नगत्या गम्. 2 भिन्नस्वरेण वद् 1 P. **-ingly,** *adv.* खंडशः, लवशः; भिन्नगत्या, भिन्नस्वरेण.

Mind, *s.* मनस् *n.*, मानसं, चित्तं, चेतस् *n.*, बुद्धि *f.*, मति *f.*, धीः; प्रज्ञा, बोधः; *See* **Intellect.** 2 हृदयं, हृद् *n.*, अंतःकरणं, चित्तं, मनः, चेतः, अंतरं. 3 मतिः, बुद्धिः, मतं; कामः, इच्छा, वांछा, रुचि *f.*, मनोरथः, वासना, भावः, ईप्सितं, अभिलाषः. 4 अभिप्रायः, उद्देशः, संकल्पः, अभिमतं, मतिः, बुद्धिः, मतं. 5 स्मरणं, स्मृति *f.*, स्मरणशक्ति *f.*, अनुबोधः; 'to give the m. to' मनः-मनो निविश् c. or बंध् 9 P or आ-नि-धा 3 U, आसक्त-निविष्ट-चित्त-*a.* भू; *See* under **Set;** 'out of one's m.' भ्रांत-अव्यवस्थित-बुद्धि (*a.*); 'fixed in the m.' चित्तनिष्ठ; 'of low m.' कृपण-नीच-बुद्धि; 'working of the m.' चित्त or मनो-व्यापारः or वृत्ति *f.*, मनश्चेष्टा, चेतोविकारः; 'according to one's m.' यथाकामं, यथेष्टं, यथेप्सितं, यथारुचि; 'have a m. to ask' प्रष्टुमनाः-कामः; 'to cross the m.' मनसि उद्-इ 2 P or उद्भू 1 P, बुद्धौ संजन् 4 A; *See* **Occur;** 'call to m.' स्मृ 1 P, सं-अनु-°, अनुचिंत् 10; 'put in m.' स्मृ c., अनु-उद्-बुध् c.; 'of one m.' एकचित्त-*a.*; 'being of one m.' एकचित्तीभूय; 'change of m.' बुद्धि-मति-भेदः; 'flashing across the m.' स्फुरणं, सहसा आविर्भावः. **-v.** *t.* मन् 4 A, गण् 10, [illegible] 6 A, अव-अप-ईक्ष् 1 A, आलोच् 10, अव-धा 3 U, चित्ते-मनसि-कृ 8 U, अवधृ 10, मनो धा 3 U. 2 सेव् 1 A, भज् 1 U, अनु-ष्ठा 1 P, अनुरुध् 4 A, अनुवि-धा 3 U. 3 रक्ष् 1 P, पा c. (पालयति); 'never m. the first question, answer the second' आस्तां-तिष्ठतु-तावत् प्रथमः प्रश्नः, द्वितीयस्य उत्तरं देहि; 'never m.' अनुर्वर्यमेतत्; *See* **Matter.** **-ed,** *a.* प्रवृत्त, प्रवण, शील, मनस्, मनस्क in comp.; 'worldly-m.' संसारासक्तचित्त, धीरमनस्क, &c. **-ful,** *a.* सावधान, अवहित, जागरूक, अवहितचित्त. 2 कृतादर, मन्यमान, अवेक्षक. 3 अवधारयत्, स्मरत्, चित्ते कुर्वत्; 'to be m. of' स्मृ. **-fully,** *adv.* सावधानं, सादरं, अवेक्षया. **-fulness,** *s.* अवधानं, अवेक्षा. **-less,** *a.* अनवधान, प्रमत्त, अनवेक्षक, निरपेक्ष. 2 नष्टस्मृति-बुद्धि; बुद्धिहीन.

Mine, *a.* मदीय, मामकीन, मामक (मिका *f.*), मत् in comp. **-s.** आकरः, ख(खा)नि-नी *f.*, उत्पत्तिस्थानं; 'm. for jewels' मणिभूमि *f.*, रत्नाकरः, (fig.) आकरः, निधिः, राशिः. 2 संधिः, सुरंगा, खानिकं, कुल्या. **-v.** *t.* खन् 1 P, आ-नि-°, अधस्तात् खन्, ऊर्ध्वं भिद् 7 P or वि-दृ 9 P, सुरंगां कृ. **-er,** *s.* खनकः, खातकः, आखनिकः, खनितृ *m.* 2 सुरंगाकारः, सौरंगिकः. **-Mineral,** *s.* धातुः, खनिजं, आकरजं वस्तु. **-a.** धातुसंबंधिन्, धातु in comp. 2 खनिज, आकरज, आकरोद्भव. 3 धातुमय (यी *f.*), धातुरूप. 4 धातुसंसृष्ट, धातुधर्मोपित. **-ogy,** *s.* धातुविद्या, धातुपरीक्षणविद्या-शास्त्रं. **-ogist,** *s.* धातुविद्याज्ञः.

Mingle, *v. t.* मिश्र् 10, वि-सं-व्या-°, संयुज् 7 U, 10, संसृज् 6 P, संपृच् 2 A, 7 P, संकॄ 6 P, संमिल् c., मिश्रीकृ 8 U, एकीकृ; उत्कंठासाधारणं परितोषमनुभवामि (S. 4) 'I experience pleasure m. ed with regret.' **-v.** *i.* संमिल् 6 P, मिश्री-एकी-भू 1 P, संकॄ-संसृज्-pass. **-ed,** *a.* मिश्रित, संयुक्त, संसृष्ट, सं-,मिश्र, संकीर्ण. **-ment,** *s.* संमिश्रणं, संसर्गः.

Miniature, *a.* सूक्ष्माकार, सूक्ष्म. **-s.** Ex. by ह्रस्व or सूक्ष्म; 'world in m.' ह्रस्वमानेन विश्वं.

Minikin, *s.* सूचिका. 2 **Minion,** q. v.

Minim, *s.* बिंदु *m.* **-um,** *s.* अल्पिष्ठा-अत्यल्पा-संख्या.

Minion, *s.* वल्लभः, प्रियः, नृप-राज-वल्लभः; *See* **Favourite.**

Minister, *s.* सचिवः, मंत्रिन् *m.*, अमात्यः, प्रकृतिपुरुषः, धुर्यः, धूर्वहः, धुरीणः, धुरंधरः, महामात्रः, राजसचिवः, राजामात्यः. 2 नियोगिन् *m.*, नियुक्तः, नियोज्यः, कर्मकरः, अधिकृतः. 3 उपाध्यायः, आचार्यः, पुरोहितः. 4 राजदूतः, राजप्रतिनिधिः; 'prime m.' प्रधान-

मुख्य-मंत्री, प्रधानसचिवः; 'm. of counsel' धीसचिवः, अमात्यः; 'm. for ordinary affairs' कर्मसचिवः. -*v.* सेव् 1 A, परि-उप-चर् 1 P, उपास् 2 A, उप-स्था 1 U, श्रु desid. (शुश्रूषते). 2 (उपकरणद्रव्याणि) परिक्लृप् c., संभृ 1 P, उप-पद् c., उप-स्था c. (स्थापयति). 3 (to) सं-पद् 4 A; क्लृप् 1 A; *See* **Tend.** **-ial,** *a.* मंत्रिसंबंधिन्, नियोगसंबंधिन्, उपचारपर, सेवक, अनुवर्तिन्, gen. ex. by (*s.*) in comp.; 'm. duties' सचिवकार्याणि. **-*Ministration,*** *s.* मंत्राधिकारः, साचिव्यं. 2 उपचारः, उपासना, सेवा, शुश्रूषा, उपकारः. 3 उपाध्यायवृत्ति *f.* **-*Ministry,*** (**Ministership**), *s.* साहाय्यं, द्वारं, कर्तृत्वं, कारणत्वं. 2 साचिव्यं, मंत्रित्वं, मंत्राधिकारः, अमात्य-साचिव्य-पदवी. 3 नियोगः, अधिकारः, नियोगिपदं. 4 सचिव-मंडलं, मंत्रिगणः-मंडलं-वर्गः, मंत्रिणः, अमात्याः, सचिवाः, राज्यधूर्वहाः. 5 पौरोहित्यं, उपाध्यायपदं.

Minium, *s.* *See* 'red lead' under **Lead.**

Minor, *a.* स्वल्पतर, अल्पीयस्, कनीयस्, न्यून, अवर. 2 अप्रधान, गौण (णी *f.*), अमुख्य. 3 क्षुद्र, लघु, लघ्वर्थ, अगुरु; gen. ex. by उप pr.; 'm. portion' उपविभागः, उपांगं; उपदेवता, उपग्रहः, उपधर्मः, &c.; 'm. consideration' लघ्वर्थः-अगुरुः-क्षुद्रः-विचारः. -*s.* अप्राप्तव्यवहारः, अप्राप्तवयस्कः, व्यवहारायोग्यः, अप्राप्तव्यवहारदशः, बालः. **-ity,** *s.* बालदशा, बाल्यं, बालावस्था, अप्राप्तव्यवहारता; बाल-शिशु-भावः. 2 न्यून-अल्प-पक्षः-संख्या, स्तोकसंख्या; 'being in the m.' न्यूनपक्षाश्रितः.

Minotaur, *s.* वृषनरः, नरवृषभः.

Minstrel, *s.* मा(म)गधः, वैतालिकः, बंदिन् *m.*: स्तुतिपाठकः, मधुकः, संगीतकुशलः-निपुणः; 'celestial m.' गंधर्वः, चारणः. **-sy,** *s.* संगीतं, गीतवादनं, गांधर्वं, गंधर्व-मागध-वृत्ति *f.*

Mint, *s.* टंकशाला, मुद्रांकनशाला; (fig.) खनि *f.*; *See* **Mine;** 'm.-master' टंकाध्यक्षः, टंकपतिः, रूप्याध्यक्षः, नैष्किकः. -*v. t.* मुद्राभि अंक् 10. 2 Forge, Invent, q. v. **-age,** *s.* मुद्रांकनं. 2 मुद्रा, मुद्रितरूप्यं.

Minus, *a.* न्यून, ऊन in comp.; 'm. a cubit' हस्तन्यून. 2 ऋणं, क्षयः; oft. ex. by वियुत, वर्जित, ऊन in comp.; '10 m. 1' एकवियुता दश; '100 m. 1' एकोनशतं, एकहान्या शतं.

Minute, *s.* क्षणः, पलं, निमि(मे)षः. 2 कला. 3 लेखः, लिखितं. -*v. t.* लिख् 6 P, स्मरणार्थं लिख्. -*a.* सूक्ष्म, अणु, अत्यल्प, अतिसूक्ष्म, अणिष्ठ, क्षुद्र, प्रतनु. 2 निपुण, सावधान, सूक्ष्म. 3 सूक्ष्मदृष्टि, सूक्ष्मदर्शिन्; 'after m. inquiries' निपुणं अन्विष्य; 'm. description of a woman' तरुणीसूक्ष्मावयववर्णनं or -अत्यवयववर्णनं. **-ly,** *adv.* सूक्ष्मं, लवशः, अणुशः; स्निग्धं, निपुणं, सूक्ष्मबुद्ध्या; 'while m. looking at the ring' अंगुलीयकं स्निग्धं निर्वर्णयंती (M. 1). **-ness,** *s.* सूक्ष्मता, अत्यल्पता, अतितनुता, &c. **-Minutiæ,** *s.* सूक्ष्मावयवाः, परमाणवः.

Minx, *s.* धृष्टा, अविनीता, बंधकी, भ्रष्टा, असती.

Miracle, *s.* अद्भुतं, अलौकिकक्रिया-कर्मन् *n.* अद्भुत-लोकोत्तर-कर्म, आश्चर्यं; चमत्कारः, अतिमानुषं कर्म, दैवं कर्म. **-*Miraculous,*** *a.* अद्भुत, लोकोत्तर, आश्चर्यभूत, आश्चर्य, अमानुष (षी *f.*), अतिमर्त्य, दिव्य, अपौरुषेय (यी *f.*). 2 अद्भुतशक्तिसंपन्न; 'm. weapon' दिव्यास्त्रं. **-ly,** *adv.* अद्भुततया, दिव्यशक्त्या.

Mirage, *s.* मृगतृष्णा-तृष्णिका, मरीचिका, मृगजलं.

Mire, *s.* पंकः, कर्दमः, जंबालः-लं, मलः-लं; 'get into the m.' संकटे निक्षिप् pass. or पत् 1 P. -*v. t.* पंकेन दुष् c. (दूषयति) or लिप् 6 P. **-y,** *a.* पंकिल, सकर्दम, सपंक, समल, कलुष, पंकक्लिन्न, पंकदूषित.

Mirror, *s.* दर्पणः, आदर्शः, मुकुरः, आत्मदर्शः. 2 (Fig.) आदर्शः, प्रतिमा. -*v. t.* **Reflect,** q. v.

Mirth, *s.* हास्यं, प्र-,मोदः, उल्लासः, आनंदः, कौतुकं, परिहासः; *See* **Merriment.** **-ful,** *a.* हृष्ट, उल्लसित, आनंदित, प्रमुदित; *See* **Merry.**

Misacceptation, *s.* अन्यथा-विपरीत-ग्रहणं.

Misadventure, *s.* *See* **Calamity.**

Misanthropy, *s.* नर-जन-द्वेषः, विश्वशत्रुता, सर्वलोकद्वेषः. **-ic, -ical,** *a.* नर-जन-द्वेषिन्, विश्ववैरिन्-द्वेषिन्. **-ist,** *s.* जन-नर-द्वेषी-शत्रुः, सर्वलोकशत्रुः, विश्वशत्रुः.

Misapply, *v. t.* अन्यथा-मिथ्या विनि-प्र-युज् 7 A, 10 or व्यय् 10 or निक्षिप् 6 P. **-ication,** *s.* दुर्विनियोगः, कुव्ययः, अपव्ययः.

Misapprehend, *v. t.* अन्यथा-मिथ्या-ग्रह् 9 U or बुध् 1 P, विपरीतं उपलभ् 1 A. **-Misapprehension,** *s.* अन्यथा or विपरीत-ग्रहणं or बोधः, भ्रमः, मिथ्यामति *f.*

Mis-appropriate, *v. t.* अपहृ 1 P. 2 अस्थाने युज् 7 P.

Misbecome, *v. t.* न युज् pass. or उप-पद् 4 A.

Misbegot, *a.* विजात, कुजन्मन्.

Misbehave, *v. i.* असम्यक्-अयुक्तं आचर् 1 P or वृत् 1 A. **-ed,** *a.* दुर्वृत्त, दुःशील, दुर्विनीत, दुराचार. **-Misbehaviour,** *s.*

अविनयः, दुर्वृत्तता, दुराचारः, कुचेष्टितं, अनार्यवृत्ति *f*.

Misbelieve,-belief, *See* **Distrust.**

Miscalculate, *v. t.* अन्यथा-मिथ्या-गण् 10. **-ion,** *s.* मिथ्यागणनं, कुगणना.

Miscall, *v. t.* मिथ्या अभि-धा 3 U or आ-ख्या 2 P.

Miscarry, *v. i.* गर्भः स्रु 1 P or पत् 1 P or च्यु 1 A (with gen. of woman); च्युतगर्भा भू 1 P. **2** न सिध् 4 P, विफलीभू, मोघी-वृथा-भू, प्रतिहन्-भंज्- pass. **-iage,** *s.* गर्भस्रावः-पातः-पतनं-च्युति *f*. **2** असिद्धि *f*., वैफल्यं, भंगः, अशुभफलं, दुर्गति *f*. **3** दुराचारः, कुनीति *f*., अविनयः; 'to cause m.' गर्भं स्रु c. or पत् c.

Miscellaneous, *a.* सं-प्र-कीर्ण, नानाविध, नानाजातीय, विविधप्रकार, नाना-भिन्न-जातीय, विविध. **-ly,** *adv.* संकीर्णं. **-Miscellany,** *s.* संकरः, प्रकीर्णकं, नानाद्रव्य or नानाविषय-संग्रहः or संनिपातः,संकीर्णवस्तु-समुदायः-संग्रहः.

Mischance, *s.* *See* **Calamity.**

Mischief, *s.* अपकारः, हानि *f*., हिंसा, क्षति *f*., नाशः, अपायः, ध्वंसः, दोषः, बाधा, अहितं, अनर्थः, अनिष्टं, अरिष्टं; 'm. to crops' शस्यहिंसा. **2** कुचेष्टितं, पापं, दुराचारः, कुचेष्टा; 'm.-maker' दुर्जनः, दुर्वृत्तः, पिशुनः, कर्णेजपः, उपजापकः, कुव्यापारिन्, कुचेष्टः; 'm.-making' दौर्जन्यं, पैशुन्यं, कुचेष्टा, दुर्वृत्तिः, कुनीति *f*. **-Mischievous,** *a.* घातुक, हिंसक, हिंसात्मक, अपकार-हिंसा-शील, हिंसारुचि, अपकारिन्, अहितकारिन्, दुष्ट, पाप, दुर्बुद्धि, दुष्टमति. **2** कुचेष्टित, कुचेष्टाप्रिय, दुर्गुणिन्, दुश्चेष्टित; 'm. trick' कुचेष्टितं; 'a m. person' लोककंटकः, कुचेष्टाप्रियः. **-ly,** *adv.* दुष्टबुद्ध्या, सापकारं, क्षतिपूर्वं, हिंसया. **-ness,** *s.* हिंस्रता, अपकारशीलता, हिंसारुचि *f*., दुष्टबुद्धि *f*., पापात्मता.

Miscomputation, *s.* मिथ्यागणना.

Misconceive, *v. t.* मिथ्या ग्रह् 9 U, अन्यथा बुध् 1 P or उपलभ् 1 A or अवगम् 1 P. **-Misconception,** *s* मिथ्या-मति-बुद्धि *f*., मिथ्या or अन्यथा-ग्रहणं or बोधः, विपरीतार्थबोधः, भ्रमः.

Misconduct, *v. t.* असम्यक् निर्वह् c. or प्र-णी 1 P or प्रवृत् c. **2** (Oneself) असम्यक् आचर् 1 P or वृत् 1 A. **-s.** दुर्णयः. असम्यक् निर्वाहः. **2** दुराचारः, दुश्चेष्टितं, कुचरितं, कुचर्या, अविनयः, मर्यादातिक्रमः, कुकृत्यं.

Misconjecture, *v.t.* मिथ्या तर्क् 10 or ऊह् 1 A. **-s.** मिथ्यातर्कः, मिथ्यानुमानं.

Misconstrue, *v. t.* मिथ्या-अन्यथा-अर्थं बुध् 1 P or ग्रह् 9 U, मिथ्या युज् 10 or अर्थं व्या-ख्या 2 P. **-Misconstruction,** *s.* अन्यथार्थबोधः, विपरीत-मिथ्या-ग्रहणं- बोधः.

Miscreant, *s.* पापः, खंडितवृत्तः, खलः, नराधमः, पापिष्ठः, दुरात्मन् *m*., दुर्वृत्तः, जाल्मः; *See* **Villain. 2** नास्तिकः, मिथ्यादृष्टिः.

Misdeed, *s.* दुष्कृतं, अपक्रिया, कुकर्मन् *n*. कुकृत्यंक्रिया, दुष्कृति *f*., अपचारः, कुचरितं, पापं.

Misdemean, *v. i.* *See* **Misbehave.**

Misdirect, *v. t.* विमार्गं दृश् c. or दिश् 6 P, विपथं दिश्. **2** '**Address**' (wrongly), q. v. **-ion,** *s.* विमार्गदर्शनं; मिथ्योपदेशः.

Misdoer, *s.* पापः, पापकर्मन् *m*., पापकृत् *m*., कुकर्मा. **-Misdoing,** *s* **Misdeed,** q.v.

Misemploy, *v. t.* अन्यथा विनि-युज् 7 A, 10 or व्यापृ c. **-ment,** *s.* असद्व्ययः, कुविनियोगः, अपव्ययः.

Miser, *s.* कृपणः, कदर्यः, क्षुद्रः, मितंपचः, किंपचानः, दृढ-बद्ध-मुष्टिः, अदानशीलः, दानशत्रुः-विमुखः. **-ly,** *a.* कृपण, कदर्य, क्षुद्र, बद्ध-दृढ-मुष्टि, दानविमुख (खी *f*.), अदानशील, मितंपच, स्वल्पव्ययिन्, व्ययविमुख, अनुदार.

Misery, *s.* दुःखं, विपद्-आपद् *f*., व्यसनं, दैन्यं, निःस्वता, विपत्ति *f*., दुर्गति *f*., दुर्दशा, कृच्छ्रं, अनिष्टं, कष्टं, अनर्थः. **2** अतिदुःखं, गाढशोकः, दैन्यं, अनिर्वृति *f*., क्लेशः, अतिव्यथा-बाधा-वेदना, परि-सं-तापः. **-Miserable,** *a.* दुःखित, दुःखान्वित, अतिदुःखार्त, अनिर्वृत, निरानंद, कष्टप्राय, अतिक्लेशार्त, वि-आ-पन्न, आपद्-विपद्-ग्रस्त, दुर्गत, मंदभाग्य, दैवोपहत, दुर्भाग्य, दुःखापन्न, दुर्दशापन्न; 'a m. man' तपस्विन् *m*., नरहतकः. **2** कृपण, दीन, तुच्छ, गर्हणीय, गर्ह्य, कुत्सित, निंद्य, नि-अप-कृष्ट, अधम, क्षुद्र; *See* **Mean.**

Misfeasance, *s.* अतिक्रमः, विकर्मन् *n*.

Misfortune, *s.* मंदभाग्यं, दुर्दैवं, दुर्भाग्यं, दुर्जातं. **2** अनर्थः, अनिष्टं, व्यसनं, आ-वि-पद् *f*., कृच्छ्रं, दुःखं, अत्याहितं, कष्टं, दुर्गति-विपत्ति-*f*., अपायः, अनिष्टपातः; 'm.s never come single' रंध्रोपनिपातिनोऽनर्थाः (S. 6), छिद्रेष्वनर्था बहुलीभवंति. **3** अलक्ष्मीः, निर्ऋति *f*.

Misgive, *v. t.* Ex. by वि-आ-शंक् 1 A, न प्रति-इ or विश्वस् 2 P, विक्लृप् 1 A, वेप् 1 A, *See* **Doubt;** 'my mind m.s me' उदेति मे मनसि शंका, शंकते-वेपते मे हृदयं. **-ing,** *s.* शंका, आ-वि-°, संदेहः, संशयः, विकल्पः, अप्रत्ययः, अविश्वासः.

Misgotten, *a* अन्यायार्जित.

Misgovern, *v. t.* असम्यक् शास् 2 P or पा c. (पालयति) or ईश् 2 A. **-ment,** *s.* कुशासनं, असम्यक् पालनं.

Misguide, *v. t.* अपथे पत् c., विमार्गेण-कुपथेन-नी 1 P or प्रवृत् c., विमार्गे दृश् c. **-ed,** *a.* उन्मार्गप्रवृत्त, मार्गभ्रष्ट, सत्पथभ्रष्ट, कुमंत्रित, दुर्विनीत, अपथगामिन्.

Mishap, *s.* *See* **Misfortune**

Misinform, *v. t.* अन्यथा नि-विद् c., मिथ्या कथ् 10 or वि-ज्ञा c (ज्ञापयति), मृषा बुध् c.

Misinterpret, *v. t.* *See* **Misconstrue.**

Misjudge, *v. i.* मिथ्या-अन्यथा-विचर् c.

Mislay, *v. t.* अस्थाने नि-धा 3 U or रक्ष् 1 P, नश् c.; *See* **Lose.**

Mislead, *v. t.* प्र-लुभ् c., वंच् 10; *See* **Cheat;** विमार्गेण-उत्पथं-नी 1 P or गम् c. (गमयति), भ्रम् c. (भ्रमयति), मुह् c., भ्रमं-भ्रांतिं-उत्पद् c., विमार्गं दृश् c. or उपदिश् 6 P, अन्यथा उपदिश्. **-ing,** *a.* भ्रमकारिन्, मोह-भ्रांति-जनक (की *f.*). **-Misled,** *a.* विमार्ग or उन्मार्गगामिन् or प्रवृत्त, भ्रांत, सत्पथभ्रष्ट, कुमार्ग-गामिन्-प्रवृत्त, भ्रांतबुद्धि.

Mislike, *v. t.* *See* **Dislike.**

Mismanage, *v. t.* असम्यक् निर्वह् c. or प्र-णी 1 P or प्रवृत् c. **-ment,** *s.* दुर्निर्वाहः, कुप्रणयनं, कुनीति *f.*, अव्यवस्था, दुर्णयः.

Misname, *v. t.* नामांतरेण-अन्यथा अभि-धा 3 U, मिथ्यानाम कृ 8 U.

Misnomer, *s.* मिथ्यानामन् *n.*, मिथ्या or अन्यथा-संज्ञा or नाम, अचरितार्था संज्ञा, असंगत-अननुरूपं नाम.

Misogamy, *s.* विवाहद्वेषः-निंदा. **-ist,** *s.* विवाहद्वेषिन् *m.* [षिन् *m.*

Misogyny, *s.* स्त्रीद्वेषः-निंदा. **-ist,** *s.* स्त्रीद्वे-

Misplace, *v. t.* अस्थाने नि-धा 3 U or निविश् c. or निक्षिप् 6 P or कृ 8 U, असम्यक् प्र-विनि-युज् 7 A, 10.

Misprint, *s.* अशुद्धं, मुद्रणदोषः.

Mispronounce, *v. t.* अशुद्धं उच्चर् c.

Misproportion, *v. t.* *See* **Disproportion.**

Misquote, *v. t.* अन्यथा-अयथार्थं-उद्धृ 1 P or अव-तॄ c. **-ation,** *s.* अयथार्थं अवतरणं.

Misreport, *v. t.* मिथ्या-अन्यथा-निविद् c. or कथ् 10 or आ-ख्या 2 P. **-s.** अन्यथा-निवेदनं, मृषाकथनं, अयथार्थाख्यानं.

Misrepresent, *v. t.* मिथ्या कथ् 10 or वर्ण् 10, असत्यं निविद् c. or ख्या 2 P, अर्थं सार्थीकृ 8 U or परिवृत् c. **-ation,** *s.* मिथ्याकथनं-निवेदनं, मिथ्या-अन्यथा-मृषा-वादः -वर्णनं, असत्यकथनं-वर्णनं.

Misrule, *s.* कुशासनं, दुर्णीति *f.*, असम्यक् पालनं-शासनं.

Miss, *s.* (As a prefixing title) ex. by भर्तृदारिका, कुमारी. **2** भ्रमः, दोषः, अपराधः, भ्रंशः. **3** हानि *f.*, अभावः, विरहः, नाशः, लोपः; *See* **Loss.** **-v.** *i.* मोघी-विफली-भू 1 P, न सिध् 4 P; 'never-m. ing arrow' अमोघः बाणः. **2** भ्रंश् 1, 4 P, भ्रश् 4 P, स्खल् 1 P. **3** वृत् 1 A: *See* below. **-v.** *t.* भ्रंश् 1 A, 4 P, च्यु, विच्यु 1 P (with abl.), हा pass. (with instr.); *See* **Lose;** 'he m. ed the mark in shooting' स लक्ष्यच्युतसायकः, निमिषादपराद्धेषुः; 'm. ed his way' मार्गाद् भ्रष्टः &c. **2** न प्राप् 5 P or विद् 6 U or लभ् 1 A, (Get q. v.). **3** क्षिप् 6 P, हा 3 P, त्यज् 1 P, अपास् 4 U, विसृज् 6 P; 'you have m. ed a splendid opportunity' शोभनावसरस्त्वया क्षिप्तः, न गृहीतः, त्यक्तः. **4** (Feel the absence of) अभावं ज्ञा 9 U or वि-सृ c., न्यून-*a.* मन् 4 A; उत्कंठ् 1 A, उत्सह् 4 P, उत्सुकायते (D.); 'I m. him very much' तस्य बलवदुत्कंठे, तस्यासन्निधानात् नितरां दुःखितोस्मि, तद्दर्शनाय उत्साम्यामि, तद्विरहविधुरः &c. **-ing,** *a.* नष्ट, भ्रष्ट, स्थानभ्रष्ट-च्युत,-तिरोहित, अदृष्ट; 'one man is m.' एको नर ऊनो दृश्यते. **2** उत्सुक, उत्कंठित, उत्कलिकाकुल.

Mis-shaped,-shapen, *a.* वि-अप-कु-रूप, कदाकार, विकृताकार.

Missile, *s.* अस्त्रं, शस्त्रं, प्रहरणं, आयुधं, क्षिपणिः. **2** चक्रं. **-a.** क्षेपणीय.

Mission, *s.* दौत्यं, प्रेरणं, प्रेषणं; 'sending or on a m.' प्रतिशासनं. **2** नियुक्त or प्रेरित गणः or जनसमूहः, नियोगिवर्गः. **-ary,** *s.* धर्मार्थं प्रेरितः, धर्मप्रसारार्थं नियुक्तः or प्रेषितः.

Missive, *s.* संदेशः, पत्रिका; *See* **Message.** **2** वार्ता-संदेश-हरः. **-a.** मुक्त, क्षिप्त, अस्त. **2** प्रेरित, प्रेषित, नियुक्त.

Mis-spell, *v. t.* अक्षराणि पर्यस् 4 U, अन्यथा लिख् 6 P. **-ing,** *s.* अक्षरविपर्यासः-व्यत्ययः.

Mis-spend, *v. t.* वि-क्षिप् 6 P, अपात्रे-अस्थाने-व्यय् 10 (व्ययपति) or प्र-विनि-युज् 7 A, 10, असद्व्ययं कृ 8 U,

Mis-state, *v. t.* मिथ्या-अयथातथ-अन्यथा-कथ् 10 or नि-आ-विद् c. or ख्या 2 P. **-ment,** *s.* अन्यथा-निवेदनं-विज्ञप्ति *f.*, मिथ्याकथनं-वादः.

Mist, *s.* कुहा, कुज्झटि-टी-टिका *f.*, कुहेलिका, धूमि(पि)का, खबाष्पः, तुषारः. **-y,** *a.* कुहाच्छन्न, धूमिकावृत, तुषारवृत. **2** गहन, अदुर्गम, अस्पष्ट; *See* **Faint.**

Mistake, *s.* भ्रमः, भ्रांति *f.*, व्या-,मोहः, मतिभ्रमः, मिथ्या-मति *f.*-बुद्धि *f.* **2** प्रमादः, दोषः, स्खलितं; 'm. in calling names' गोत्रस्खलितं. **-v.** *t.* अन्यथा-मिथ्या-ग्रह् 9 U or मन् 4 A or बुध् 1 P, मिथ्या ज्ञा 9 U, भ्रांत्या-संदेहेन-मन्, संदिह् 2 U; gen. ex. by बुद्धिः, धीः in comp. or by *s.* (1); 'why do you strike me, m. ing me for Siva' पुरारातिभ्रांत्या मां किं प्रहरसि; व्याप्रधिया-बुद्ध्या तस्माद् पलायंते, केचनकलैः

संदेहितसूलराशिभिः (Ka. 23); 'which were m. en for heaps of cotton'. केतकशिखासंदिग्धमुग्धेन्दुः (Mal. 1) 'the lovely moon being m. en for a Ketaka point.' -v. i. भ्रम् 1, 4 P, मुह् 4 P, प्रमद् 4 P, स्खल् 1 P, अपराध् 4, 5 P; 'you m. in this opinion' अयं तवाभिप्रायः भ्रम एव, भ्रांतः. -able, a. संदिग्ध; 'in no m. terms' असंदिग्धवचोभिः. -en, a. भ्रांत, प्रमादिन्, मूढ, संदिग्ध. 2 अयथार्थ, अशुद्ध, मृषा-मिथ्या-अन्यथा-in comp.; 'a m. opinion' मतिभ्रमः, मिथ्यामतिः.

Mister, *s.* आर्यः, श्री pr.

Mis-timed, *a. See* **Late**.

Mistle-toe, *s.* वृक्षाश्रया, तरुरोहिणी.

Mistress, *s.* गृहिणी, गेहिनी, गृहस्वामिनी, कुटुंबिनी; स्वामिनी, अधिष्ठात्री, शासित्री, अध्यक्षा, सेव्या, ईश्वरी, भट्टिनी (of servants). 2 अध्यापिका, आचार्या, उपदेशिका, अध्यापयित्री, उपाध्याया-यी. 3 उपपत्नी, उपपत्नी, भुजिष्या, अवरुद्धा. 4 प्रिया, प्रियतमा, वल्लभा, कांता दयिता, रमणी, कामिनी, प्रमदा. 5 कुशला, निपुणा.

Mistrust, *v. t.* न विश्वस् or प्रति-इ 2 P, शंक् 1 A. -s. अविश्वासः, अप्रत्ययः, आ-परिशंका, अप्रतीति *f.* -ful, *a.* अविश्वासिन्, अप्रत्ययिन् *m.* शंका-अश्रद्धा-शील, साशंक, आशंकित, शंकिन्, संदेहिन्. -fully, *adv.* साशंकं, अविश्वासेन. -fulness, *s.* अप्रतीतिः, आशंका.

Misunderstand, *v. t.* मिथ्या-अन्यथा समर्थ् 10 or क्लृप् c. or मन् 4 A or ग्रह् 9 U or सं-भू c. or उपलभ् 1 A or अवगम् 1 P or बुध् 1 P; 'don't m. me' अलमन्यथा गृहीत्वा (M. 1), अलमस्मानन्यथा संभाव्य (S. 1). -ing, *s.* मिथ्या or अन्यथा-ग्रहणं or संभावनं, मिथ्यामति *f.*-बोधः, अयथार्थबोधः, भ्रमः. 2 वैमत्यं, मतिभेदः, विसंवादः, द्वैधं, विमत-मति *f.*

Misuse, *v. t.* मिथ्या-असम्यक् प्र-विनि-उप-युज् 7 A, 10, अनुचितं-अस्थाने व्यापृ c. or व्यव-हृ c., अप-व्यय् 10 (व्ययति). -s., -age, *s.* कुप्रयोगः, असत्प्रयोगः, कु or असम्यक्-व्यापारः or व्यवहारः, अन्यथोपयोगः, असद्विनि-योगः, अपव्ययः.

Mite, *s.* अणुः, लवः, कणः, लेशः, कणिका, अल्पमात्रा. 2 धनलवः-लेशः, अत्यल्पं धनं, काकिणी, कपर्दिका.

Mithridate, *s.* विषनाशनं, विषघ्नं.

Mitigate, *v. t.* शम् c. (शमयति), प्र-उप-°, लघू-कृ 8 U, लघयति (D.), न्यूनीकृ, अल्पीकृ, नि-यम् 1 P or c.; *See* **Moderate**; 'to be m. ed' शम् 4 P, लघूय् 1 P. -ion, *s.* शमः, शमनं, शांति *f.*, प्र-उप-°, लघूकरणं, न्यूनता. -ive, -Mitigant, *a.* शमक, शांतिद, शांतिकर (री *f.*).

Mix, *v. t.* मिश्र् 10, सं-व्या-वि°-, संयुज् 7 U, 10, सं-यु 2 P; संसृज् 6 P, संपृच् 2 A, 7 P, प्रक्षिप् 6 P, एकीकृ 8 U, एकत्र कृ, संमिल् c. 2 संकृ 6 P, संकुलीकृ. -v. i. मिश्रीभू 1 P, संमिल् 6 P, संकृ-संयुज-संसृज्-pass.; संयोगं-संसर्गं-इ-या 2 P or गम् 1 P, संगम् 1 A, संगमनुभव् 1 P, सं-सृ. -ed, *a.* मिश्रित, संयुक्त, संसृष्ट, संपृक्त, संयुत, व्या-सं-मिश्र, समवेत, संबद्ध. -ing, -ture, *s.* मिश्रणं, संयोगः, संसर्गः, संपर्कः. 2 मिश्रता, संयुक्तता, संसृष्टता, संकीर्णता. 3 संकरः, संनिपातः, नानाद्रव्य-संमिश्रद्रव्य-समुदायः, मिश्रद्रव्यं, मिश्रं.

Mixen, *s.* विट्-पुरीष-राशिः.

Mizzen-mast, *s.* पश्चिमकूपकः.

Mizzle, *s.* तुषारवर्षः, शीकरासारः

Mnemonic, *a.* स्मृतिसहायभूत, स्मरणोपकारिन्. -s. (M.s) स्मरणविद्या.

Moan, *v. i.* दीर्घं श्वस् 2 P or निश्वस् 2 P, सशब्दं आक्रंद् 1 P or आक्रुश् 1 P or विलप् 1 P, आर्तरवं मुच् 6 P; *See* **Groan, Lament.** -s. आर्तनादः-रवः, दीर्घनिश्वासः-रवः, क्रंदितं, विलपनं, परिदेवनं. -ful, *a.* विलापकारिन्, परिदेविन्. -fully, *adv.* सनिश्वासं, सविलापं.

Moat, *s.* परिखा, प्रतिकूपः, खातकं, उपकुल्या. -ed, *a.* परिखान्वित.

Mob, *s.* प्राकृतजनाः, जनसमूहः, अप्रबुद्धजनगणः, लोक or जन-संघः or संकुलं, जनता, बहुजन-मेलकः, पृथग्जनाः, नीच-अधम-जनाः.

Mobile, *a.* अस्थिर, चंचल, चपल, चरिष्णु, गतियोग्य, जंगम. -Mobility, *s.* **Mob,** q. v. 2 अस्थिरता, चांचल्यं, गतिक्षमता.

Mock, *v. t.* विडंब् 10, अव-उप-हस् 1 P. सोपहासं अनुकृ 8 U. 2 गर्ह् 1, 10 A, अव-ज्ञा 9 U, अवक्षिप् 6 P, अवमन् 4 A, अवहासास्पदं मन्; *See* **Contemn.** 3 वंच् 10, प्रतॄ c., विप्र-लभ् 1 A, मुह् c.; *See* **Cheat.** -a. कृत्रिम, कृतक, कपट-व्याज in comp.; 'm. fight' कृत्रिमयुद्धं, व्याजयुद्धं. -er, *s.* उप-अव-हासकः, अवक्षेपकः, विडंबनकृत् *m.* -ery, -ing, *s.* उप-अव-हासः, अवज्ञा, विडंबनं, अवक्षेपः, गर्हणं, तिरस्कारः, अवमानः. 2 उपहासपात्रं-आस्पदं-भूमि *f.*-पदं, अवहासस्थानं-विषयः, तिरस्कारपदं-विषयः. 3 वंचनं-ना, व्याजः, कपटं, छलं, विडंबना, विडंबनहेतुः; अनर्थकारंभः, वृथोद्यमः, वृथाप्रयत्नः, निष्फलचेष्टा. -ingly, *adv.* सोपहासं, सावहासं, सतिरस्कारं.

Mode, *s.* रीति *f.*, प्रकारः, मार्गः, पद्धति *f.*, विधिः, वृत्ति *f.*, कल्पः, क्रमः, विधा, in comp.; *See* **Manner.** 2 रूपं, आकारः, आकृति *f.* 3 आचारः, व्यवहारः, प्रचारः, रीतिः, सं-

प्रदायः. 4 सभ्य-शिष्ट-मार्गः, व्यवहारः, शिष्टाचारः. 5 वाच्यं, अर्थः. 6 रागः, रागिणी. **-al,** *a.* रूपविषयक. **-ish,** *a.* शिष्टाचारानुरूप, सम्यरीत्यनुसारिन्; *See* **Fashionable.**

Model, *s.* आदर्शः, प्रतिरूपं, प्रतिमा-मानं, उपमा-मानं; 'a m. prince' आदर्शः सर्वनृपाणां. 2 संस्कारः, संस्थानं, आकारः, आकृति *f.* **-v.** *t.* संस्कृ 8 U, रूप् 10, सरूप-*a.* कृ; तक्ष् 1, 5 P: क्लृप् c.

Moderate, *a.* परि-,मित, समर्याद, नि-सं-यत, अल्प, सावधिक. 2 नियतवृत्ति, मर्यादानतिक्रामिन्; 'm. in expenses' मितव्ययिन्, अल्पव्यय; 'm. in desires' अलुब्ध, अल्पसंतुष्ट, अल्पाकांक्षिन्; 'm. in eating' मिताहार, मिताशन, स्वल्पाहार; 'm. in speech' मितवाच्-भाषिन्. 2 (Middling) मध्यम, सामान्य, अनति-नाति- in comp.; 'trees of a m. height' नातितुंगा वृक्षाः. **-v.** *t.* शम् c. (शमयति), प्र-उप-°, लघयति (D.), लघूकृ 8 U, न्यूनी-अल्पी-कृ, नियम् 1 P or c.; छायाद्रुमैर्नियमितार्कमयूखतापः (S. 4) 'the heat of the sun's rays being m. ed by shady trees.' 2 नि-सं-यम्, निग्रह् 9 P, संहृ 1 P, आ-वृ 5 U. **-v.** *i.* शम् 4 P, निवृत् 1 A, विरम् 1 P, अल्पी-लघू-भू 1 P. **-ion,** *s.* लघूकरणं, प्रशमनं. 2 संयमः, निग्रहः, दमः, अनतिक्रमः, मर्यादानतिक्रमः, परि-,मितता-त्वं. 3 समता, समवृत्ति *f.*, समभावः, क्षमा, क्षांति *f*: 'm. in desires' अलोभः, अल्पसंतोषः, अल्पाकांक्षा. **-ly,** *adv.* परिमितं, समर्यादं, नियतं, स्वल्पं; ईषत्, आ, मंद, नाति, अनति in comp.; 'm. heated' ईषत्तप्त, मंदोष्ण, कोष्ण, &c.: 'm sharp' अनतितीव्र. **-or,** *s.* नियंतृ *m.*, मध्यस्थः.

Modern, *a.* आधुनिक (की *f.*), अधुनातन-इदानींतन-(नी *f.*), अर्वाचीन, अप्राचीन, अपुराण, नूतन, नव, नवीन, नूतनकालीन. **-ness,** *s.* नूतनता, अप्राचीनत्वं. **-Moderns,** *s.* अधुनातनाः, आधुनिकाः (pl.).

Modest, *a.* विनीत, लज्जावत्, लज्जाशील, सलज्ज, सव्रीड, शालीन, विनयवत्, सत्रप, ह्रीमत्, लज्जा-त्रपा-व्रीडा-अन्वित or युक्त, सविनय, अप्रगल्भ, अधृष्ट. 2 (not proud) अगर्व, नम्र, निरभिमान, निरहंकार, सविनय, अनुद्धत, विनत, नम्रशील. 3 अव्यभिचारिन्, साधुशील, सद्वृत्त. 4 परि-, मित, अल्पपरिमाण. **-ly,** *adv.* सविनयं, सव्रीडं, सलज्जं, सत्रपं, अगर्वं, अनुद्धतं, निरभिमानं. **-y,** *s.* विनयः, शालीनता, लज्जा, ह्रीः, व्रीडा, त्रपा, लज्जाशीलता, अप्रागल्भ्यं, अधाष्टर्यं, मर्यादा, विनीतता. 2 नम्रता, अगर्वः, अनहंकारः, निरभिमानता, अनौद्धत्यं, नम्रशीलता, विनयः. 3 अव्यभिचारः, सद्वृत्ति *f.* 4 परिमितता.

Modicum, *s.* अल्पांशः, अल्पभागः, लवः, लेशः, किंचित्, किंचन.

Modify, *v. t.* रूपं परिवृत् c. or परिणम् c. (-णमयति), विकृ 8 U or c.; रूपांतर-रूपभेदं-कृ or वि-धा 3 U. 2 नियम् 1 P, संहृ 1 P, शम् c.; *See* **Limit, Moderate.** **-ied,** *a.* विकृत, विकृतरूप, परिणतरूप, नियमित. **-ication,** *s.* रूपांतरविधानं, रूपपरिवर्तनं. 2 विकारः, विकृति *f.*, परिणामः, परिवृत्ति *f.*, रूपांतरं, रूपभेदः, विशेषः. 3 भेदः, विभेदः, विशेषः.

Modulate, *v. t.* स्वरलयं उत्पद् c., स्वरानुपूर्व्यं कृ 8 U. 2 स्वरभेदं कृ. **-ion,** *s.* संक्रमः, परिवर्तनं; 'm. of voice' स्वरसंक्रमः (Mr. 3). 2 स्वरभेदः-लयः-अनुक्रमः; स्वरानुपूर्व्यं. 3 **Melody,** q. v.

Moiety, *s.* अर्धः-र्धं, अर्धभागः-अंशः.

Moil, *v. t.* **Dirty,** q. v. **-v.** *i.* आर्त कृ 8 U, क्लेशायासेन श्रम् 4 P.

Moist, *a.* आर्द्र, क्लिन्न, सरस, उन्न, उत्त, सद्रव, सिक्त, अशुष्क, तिमित; 'to be m.' क्लिद् 4 P, स्तिम् 4 P. **-en,** *v. t.* क्लिद् c., आर्द्रीकृ 8 U, सिच् 6 P, उंद् 7 P, उक्ष् 1 P. **-ening,** *s.* क्लेदनं, उक्षणं, उंदनं. **-ness,** *s.* आर्द्रता, क्लिन्नता, सरसता. **-ure,** *s.* क्लेदः, तेमः, स्तेमः, रसः, सजलता, आर्द्रता, क्लिन्नता; oft. ex. by जलं.

Molar, *s.* दंष्ट्रा, चर्वणदंतः.

Molasses, *s.* गुडः, इक्षुसारः, मत्स्यंडी-ण्डिका, फाणितं.

Mold, *s. See* **Mould.**

Mole, *s.* तिलकः, जडुलः, कालकः, पिप्लुः. 2 वप्रः-प्रं, सेतुः, चयः, पिंडलः, आलि *f.* 3 छुच्छुंदरी, गंधमुखी, दीर्घतुंडी, दिवांधिका; 'm.-eyed' सूक्ष्मनयन,' m. hill' वल्मीकः-कं, वामलूरः, कृमिशैलः, कूलकः, स्यमीकः; 'he makes mountains of m.-hills' तिले तालं पश्यति.

Molecule, *s.* अणुः, परमाणुः, कणः.

Moles, *s.* स्यंनं.

Molest, *v. t.* बाध् 1 A, अर्द् 1 P or c., पीड् 10, उपद्रु 1 P, आ-यस् c., उपरुध् 7 U: *See* **Harass.** **-ation,** *s.* बाधा, पीडा, उपद्रवः, आयासः, क्लेशः. **-er,** *s.* उत्पीडकः, बाधकः, आयासकः.

Mollient, *a.* मृदुकारिन्, शमक, शांतिद.

Mollify, *v. t.* शम् c. (शमयति), प्र-उप-°, सांत्व् 10, मृदूकृ 8 U, लघूकृ.

Molten, *a.* विलीन; *See* **Liquid.**

Moment, *s.* क्षणः, मुहूर्तः, निमि(मे)षः, पलं; 'pleasant for the m.' आपातरमणीय; 'but for a m.' क्षणमात्रं; 'this very m.' अस्मिन्नेव क्षणे; 'the m. he is here' अत्र सन्निधानमात्रे or आगत एव; 'for the present m.' आपाततः; 'in a m.' क्षणात्,

क्षणेन, निमेषमात्रात्, एकपदे; 'auspicious m.' शुभमुहूर्तः, लग्नं; *See* **Instant** also. 2 गुरुत्वं, महत्त्वं, प्रभावः, गौरवं, महिमन् *m.*; *See* **Importance**; 'of little m.' अक्षुब्धक, अकिंचित्कर (री *f.*), लघ्वर्थ, क्षुद्र. **-ary,** *a.* क्षणिक, क्षणस्थायिन्, अस्थिर, अस्थायिन्; क्षण, निमेष in comp.; 'm. flash' अचिरप्रभा, क्षणद्युति *f.*; 'm. obstacle' क्षणविघ्नः. **-ous,** *a.* गुरु, गुरुप्रभाव, अलघु; *See* **Important.**

Momentum, *s.* जवः, वेगः, आ-सं-वेगः.

Monachism, *s.* मठवासः, संसारत्यागः, आरण्यकवृत्ति *f.*

Monad, *s.* अभेद्य-अच्छेद्य-वस्तु *n.*

Monarch, *s.* राजन् *m.*, ईशः, ईश्वरः, पतिः, अधिपः, अधीशः, स्वामिन् *m.*; *See* **Lord;** 'm. of the herd' यूथपतिः-पालः. 2 अधीश्वरः, नृपः, नृपालः, भूपतिः; *See* **King. -al, -ic,-ical,** *a.* राजकीय, राजयोग्य, राज in comp. 2 एकप्रभुक, एकराजायत्त, सम्राडधीन. **-y,** *s.* एकराजशासनं, एकराजतंत्रं, एकराजाधिपत्यं. 2 राज्यं, विषयः, राष्ट्रं.

Monastery, *s.* विहारः, मठः, आश्रमः, मुनिवासः, वानप्रस्थाश्रमः. **-Monastic, -ical,** *a.* विहारिक, आश्रमिक (की *f.*), वैखानस (सी *f.*); 'm. vow' वैखानसं व्रतं.

Monday, *s.* सोमवारः-वासरः, इंदुवासरः.

Monetary, *a.* द्रव्यसंबंधिन्, मौद्रिक (की *f.*).

Money, *s.* धनं, अर्थः, वित्तं, द्रव्यं, विभवः, वसु *n.*; *See* **Wealth.** 2 मुद्रा, निष्कः-र्ष्कं, नाणकं, टंककः; 'm.-bag' कोशः-षः, मुद्राकोषः; 'm.-changer' मुद्रापरिवर्तकः; 'm.-lender' कुसीदिकः, वार्द्धुषिकः, वृद्ध्याजीवः, वार्द्धुषिः; उत्तमर्णः. **-ed,** *a.* धनिन्, धनिक, धनसंपन्न, धनाढ्य. **-less,** *a.* धनहीन, निर्धन, निःस्व, गतविभव, परिक्षीण; *See* **Poor.**

Monger, *s.* व्यापारिन् *m.*, व्यवहारिन् *m.*,क्रयविक्रयिकः, वणिज् *m.*

Mongoose, *s.* *See* '**Mungoose.**'

Mongrel, *a.* संकीर्ण, संकरजातीय, संकरज.

Monism, *s.* अद्वैतवादः.

Monitor, *s.* शासकः, बोधकः, उपदेशकः, शिक्षकः. 2 उपगुरुः. **-y,-Monitive,** *a.* प्रबोधक, उपदेशक, शिक्षक, उपदेशरूप.

Monk, *s.* यतिः, संन्यासिन् *m.*, मुनिः, योगिन् *m.*, मठवासिन् *m.*, तपस्विन् *m.*, वानप्रस्थः. **-ish,** *a.* मुनिसंबंधिन्, यतिसदृश (शी *f.*).

Monkey, *s.* वानरः, कपिः, मर्कटः, प्लवं(व)गः, शाखामृगः, वलीमुखः, कीशः, वनौकस् *m.*; 'm.-like' कापेय (यी *f.*).

Monochord, *s.* एकतंत्रीवाद्यं.

Monochromatic, *a.* एकवर्ण-रंग.

Monochronic, *a.* समकालीन, वर्तमान.

Monocrat, *s.* अधीश्वरः, अनायत्तशासनः.

Monocular, *a.* एकाक्ष (क्षी *f.*), एकनयन, काण. 2 एकनेत्रोपयुक्त.

Monogamy, *s.* सकृद्विवाहः, एकपत्नीव्रतं, एकस्त्रीविवाहः. **-ist,** *s.* एकपत्नीकः, एकस्त्रीकः.

Monologue, *s.* आत्म-स्व-गतभाषणं.

Monomachy, *s.* द्वंद्वं, नियुद्धं, द्वंद्वयुद्धं.

Monomania, *s.* एकविषयासक्ति *f.*, एकविषयोन्मादः. **-Monomaniac,** *a.* एकविषयोन्मत्त.

Monopetalous, *a.* एकदलविशिष्ट.

Monoplane, *s.* एकतलं विमानं.

Monopoly, *s.* एकाधिकारः, अनन्यसाधारणः अधिकारः, एकव्यापारः-व्यवसायः. **-ist, -izer,** *s.* पूर्वक्रयिन् *m.*, सर्वग्राहकः. **-ize,** *v. t.* (सर्वं) पूर्वं क्री 9 U; (सर्वं) स्वायत्तीकृ 8 U, आत्मसात्कृ, अनन्यसाधारणं आत्माधीनीकृ, असामान्येन भुज् 7 A or भुज् 6 A.

Monosyllable,*s.* एकाक्षरं. **-Monosyllabic,** *a.* एकाक्षर, एकाच्; 'm. roots' एकाचो धातवः.

Monotheist, *s.* अद्वैतवादिन् *m.* **-Monotheism,** *s.* अद्वैतं, अद्वैतवादः.

Monotony, *s.* एकस्वरः-स्वनः, स्वराभेदः, एकस्वरसंतानः, स्वरसमता, स्वरभेदाभावः. 2 एकसम-समान-रूपता, विशेषाभावः, एकव्यापारसंतति *f.* **-ous,** *a.* एकस्वर-ताल-स्वन, सम-अभिन्न-स्वर. 2 एक-सम-समान-रूप, एकप्रकार, निर्विकार, निर्विशेष. **-ously,** *adv.* एकस्वरेण, समरूपेण, निर्विकारं. **-ousness,** *s.* *See* (*s.*) above.

Monsoon, *s.* वर्षाः (*f.* pl.), वर्षाकालः-समयः, प्रावृष् *f.*, मेघकालः, पर्जन्यकालः.

Monster, *s.* राक्षसः, क्रूर-घोर-कर्मन् *m.* 2 राक्षस-विकट-भीम-शरीरः-विग्रहः, बृहत्परिमाणः, विकटाकारः; *See* **Giant.** 3 अद्भुतं, अपूर्ववस्तु *n.*, अपरूपं, विरूपविषयः; 'm.s in the form of men' मानवराक्षसाः; 'm.s of the deep' मकरादयः, यादांसि. **-Monstrous,** *a.* अद्भुत, विलक्षण, अपूर्व, सृष्टिक्रमबाह्य. 2 अप-वि-रूप, विकृताकृति. 3 राक्षसरूप, घोरदर्शन, विकट-भीम-कराल-रूप-शरीर, अतिमहत्, घोररूप, घोराकृति, विकटाकार, भीम-उग्र-रौद्र-दर्शन. 4 (Of acts) दारुण, घोर, अतिबीभत्स, विकट. **-ly,** *adv.* अद्भुतं, विकटं, दारुणं, उत्कटं, भृशं, अतीव, अत्यंतं, अतिशयेन; *See* **Exceedingly. -ness, -Monstrosity,** *s.* अद्भुतता, घोरता, दारुणता, &c.

Month, *s.* मासः; 'half a m.' पक्षः; 'bright half of the m.' शुक्ल-शुद्ध-सित-पक्षः, पूर्वपक्षः; 'dark half' कृष्ण-उत्तर-तमिस्र-पक्षः, बहुलः, तमिस्रः; 'a m. old' मासजात. **-ly,**

a. मासिक (की *f.*), मास्य, प्रातिमासिक ; 'half-m.' पाक्षिक (की *f.*); 'm. allowance' मासिकं. *-adv.* मासे मासे, प्रतिमासं.

Monument, *s.* कीर्ति-यशः-स्तंभः, स्मारकचिह्नं. 2 चैत्यं, समाधिः; स्तूपः. **-al,** *a.* स्मरणार्थक, स्मरणकारिन्. 2 चैत्यसंबंधिन्.

Mood, *s.* भावः, वृत्ति *f.*, प्रकृति *f.*, अवस्था, दशा, चित्तवृत्तिः, मनोभावः ; 'an angry m.' कोपवृत्तिः. 2 वाच्यं, अर्थः. **-y,** *a.* रुष्ट, क्रुद्ध, वक्रभाव, उदासीन, उदासीनवृत्ति, चित्तोद्विग्न, विषण्ण, उद्विग्न, दीनमनस्क. 2 स्वच्छंद, स्वैरिन्; *See* **Humorsome,**

Moon, *s.* चंद्रः, शशिन् *m.*, इंदुः, सोमः, विधुः, चंद्रमस् *m.*, निशाकरः, रजनि(नी)करः, ग्लौः, शशधरः, शशांकः, मृगांकः, हिमांशुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, ओषधीपतिः, कुमुदबांधवः, द्विजराजः, कलानिधिः-नाथः, अब्जः, जैवातृकः, नक्षत्रेशः, क्षपाकरः; and comp. of पतिः, ईशः, नाथः, पः, with words for 'Night,' 'Star,' or of 'Ray' with 'Cold' or 'Nectar,' q. v.; क्षपानाथः, शीतकरः, तारानाथः, उडुपः; 'orb of the m.' बिंबः-बं, मंडलं; 'digit of the m.' कला, रे(ले)खा; 'full m.' पूर्णिमा, पौर्णमासी; 'new m.' अमा, अमाव(वा)सी, अमाव(वा)स्या, दर्शः, सूर्येन्दुसंगमः; 'm.-beam' चंद्रपादः, शशिकरः-रश्मिः, सुधांशुः, (Ray, q. v.); 'm.-light' कौमुदी, चंद्रिका, ज्योत्स्ना, चंद्र-शशि-प्रभा, चंद्रातपः; (*a.*) ज्योत्स्नावत्, ज्योत्स्नायुक्त, चंद्रप्रकाशित; 'enjoys m.-light evenings' ज्योत्स्नावतो निर्विशति प्रदोषान् (R. vi. 34); 'm. plant' सोमलता, सोमवल्ली-वल्लरी, ब्राह्मी, मत्स्याक्षी; 'm.-shine' चंद्रप्रभा-द्युति-कांति *f.*; 'm.-stone' चंद्रकांतः, सोमकांतः, चंद्रमणिः; 'm.-struck' विक्षिप्त-भ्रांत-बुद्धि, विप्लुत-हत-मति. **-less,** *a.* हत-नष्ट-चंद्र, चंद्रहीन. **-y,** *a.* चंद्रतुल्य.

Moor, *v. t.* रज्ज्वा बंध् 9 P or गतिं रुध् 7 U. **-s.** 'm.-land' कच्छः, कच्छ-अनूप-भूः. **-ish,-y,** *a.* आनूप (पी *f.*), कच्छ, in comp ; अनूप.

Moot, *v. t.* विचर् c., परीक्ष् 1 A, वि-तर्क् 10; *See* **Discuss. 2** उपक्षिप् 6 P, उपन्यस् 4 U; 'm.-case', 'm.-point' विचारविषयः-पदं-आस्पदं-स्थानं, संदिग्ध-विवादविषयः.

Mop, *s.* संमार्जनी, शोधनी. 2 वालिका, लपनी. *-v. t.* मृज् 2 P or c., शुध् c.

Mope, *v. i.* वि-अव-सद् 1 P, म्लै 1 P, दुर्मनायते (D.), विषण्णीभू 1 P. **-ing,-ish,** *a.* विषण्ण, अवसन्न, उद्विग्न, दुर्मनायमान, विषण्णवदन; *See* **Deject,-ed.**

Moppet, *s.* वस्त्रपांचालिका, पटपुत्रिका.

Moral, *a.* साधु, साधुवृत्त, सदाचार, धार्मिक-सात्त्विक- (की *f.*); नीतिमत्, नयानुसारिन्; धर्म्य, पुण्य, न्यायानुसारिन्, धर्मानुरूप, न्याय्य; gen. ex. by सत्, नीति, नय in comp., 'm. instruction' नयोपदेशः, नीति *f.*; 'm. lessons' नीतिपाठाः; sometimes by चित्त, मानस in comp.; 'm. freedom' चित्तस्वातंत्र्यं; 'm. advancement' मानसोन्नति *f.*; 'm. science' नीतिशास्त्रं; 'm. duties' शाश्वतधर्मः, सदाचारः. 2 नियमाधीन. 3 अनुमान-युक्ति-सिद्ध. *-s.* तात्पर्यं, अभिप्रायः, भावार्थः, तात्पर्यार्थः. **-ist,** *s.* नीतिशास्त्रज्ञः, नीतिज्ञः, नयज्ञः, नीत्युपदेशकः, नीतिविद्, सदसद्विवेचकः. **-ity,** *s.* नीतिः, नयः, नीति or नय विद्या or शास्त्रं, सद्व्यवहारशास्त्रं, सदसद्विवेकः-विचारः. 2 धर्मानुष्ठानं, साधुवृत्तं, पुण्यशीलता, सदाचारः, सु-सत्-चरितं, धर्मवृत्ति *f.* 3 न्याय्यता, धर्म्यता, धर्म-न्याय-अनुसारः. **-ize,** *v. t.* धर्मोपदेशास्पदीकृ 8 U. *-v. i.* नीत्युपदेशं दा 3 U or लिख् 6 P. **-ly,** *adv.* नीतिशास्त्रानुरूपं, नयतः, नीत्या, धर्मेण, धर्मतः, न्यायेन, न्यायतः. 2 युक्त्या, मनसा, अनुमानेन. **-Morals,** *s.* नीतिः, नीतिशास्त्रं-विद्या. 2 आचारः, आचरणं, वृत्तिः, चरितं, वृत्तं, व्यवहारः, रीति *f.*: 'good m.' सुशीलं, सदाचारः, साधुवृत्तं, विनयः, साधु-सु-सत्-चरितं.

Morass, *s.* कच्छः, अनूपः, अनूपभूः.

Morbid, *a.* दूषित, उद्भ्रांत, विकृत, अस्वस्थ, असुस्थ, रोगाक्रांत, व्याधित.

Morbific, *a.* रोग-व्याधि-कर (री *f.*), रोगद.

Morbose, *a.* रोगजनित, व्याध्युद्भव.

Mordacious, *a.* दंशक. **-Mordacity,** *s.* दंशकता, दंशनं.

Mordant, *a.* उग्र, अरुंतुद, तीक्ष्ण, निर्दाणर्भ.

More, *a.* अधिक, भूयस्, अधिकतर; उत्तर, अतिरिक्त, पर, अन्य; oft. ex. by तर or ईयस् affixed; 'm. in strengh' बलीयस्, प्रबलतर; 'something m.' किंचित् अन्यदपि; 'what m.' किमपरं, किमन्यत्; 'after m. than three years' समधिकाद्वर्षत्रयात्; 'm. or less' न्यूनाधिक; 'for m. than 1,000 years' परः सहस्राः शरदः. *-s.* अधिकं, आधिक्यं, अतिरेकः, अतिशयः; oft. ex. by अपरं, अन्यत्; *See* above; 'm. or less' न्यूनातिरेकः, न्यूनाधिक्यं; 'no m. of solicitation' अलं-कृतं-अतिप्रार्थनया; 'what m.' किमन्यत्; किंबहुना. *-adv.* (With adj.) ex. by अधिक in comp.; अधिकमनोज्ञ; or gen. by compar. degree in तर or ईयस्. 2 (With verbs) by अधिकं, अधिकतरं, अतःपरं, पुनः, भूयः; 'm. and m.' उत्तरोत्तरं, अधिकाधिकं; 'no m.' न अतः-इतः-परं or ऊर्ध्वं; अलं, कृतं; *See* **Enough** ;

'how much m.' किं पुनः, किमुत. -**More-over,** *adv*. अन्यच्च, अपरं-अपि-च, किंच, परं, अपि तु, अपि.

Morganatic, *a*. अनुलोम (विवाहः).

Moribund, *a*. मृतकल्प-प्राय, मुमूर्षु.

Moringa, *s*. शो(शौ-शो-शी)भाजनं, शिग्रुः, तीक्ष्णगंधकः, अ(आ)क्षीवः, मोचकः.

Morion, *s*. शिरस्कं, शिरस्त्राणं, शीर्षकं.

Morn, Morning, *s*. वि-प्र-भातं, प्रत्यु(त्यू)षः-षस् *n*.,उषा, उषस् *f*., व्युष्टं, कल्यं, अरुणोदयः, प्रातर् *ind*., अहर्मुखं, प्रभात or उषः-कालः or समयः. 2 (Opposed to afternoon) पूर्वाह्णः, प्राह्णः; 'it is broad m.' सुप्रभाता रजनी; 'in the m. प्रातः, प्रातःकाले, प्रभाते, प्रत्यूषे, व्युष्टं, प्रगे; 'I bid you good m.' 'good m. to you' शुभस्ते प्रातःकालः (भूयात्); 'early in the m.' सुप्रातः, महति प्रत्यूषे, अतिप्रगे, प्रातरेव. -*a*. प्रातः-उषः-कालीन, प्राभातिक, औषिक (की *f*.), उषस्य, प्रभातीय; gen. ex. by प्रातर् or (*s*.) in comp.; 'm. breeze' विभातवायुः; 'm. devotion' प्रातरुपासना; 'm. star' प्रभाततारा; 'm. twilight' प्रातःसंध्या.

Morose, *a*. कर्कश-कटु-वक्र-स्वभाव-प्रकृति, वाम or वक्र-भाव or शील, रूक्षस्वभाव, सदावक्र, प्रतीप, उदासीन, दुःशील, उदासवृत्ति. -**ly,** *adv*. वक्रभावेन, कर्कशभावात्, स्वभावरौक्ष्येण. -**ness,** *s*. कर्कशता, रूक्षता, वामता, वक्रता, स्वभावकटुता, वक्रशीलता, प्रतीपता, औदासीन्यं.

Morrow, *s*. पर or उत्तर-दिवसः or दिनं; 'on the m.' श्वः, परेद्युः, परेगवि, कल्ये, उत्तरेद्युः.

Morsel, *s*. कवलः, ग्रासः, पिंडः. 2 खंडः, लवः, शकलः-लं, क्षुद्रभागः.

Morsure, *s*. दंशनं.

Mortal, *s*. मर्त्यः, मनुष्यः, मर्त्यधर्मन्, जन्मिन्, प्राणिन् शरीरिन्, देहिन्, all *m*,. देह-तनुभृत्, मृत्युवशः; *See* **Man.** -*a*. मर्त्य, मर्त्यधर्मन्, मरणशील, मृत्युवश, नश्वर, नाश-मरण-अधीन, मरण-काल-आयत्त, अनित्य, विनाशिन्; 'men are m.' मनुष्या मर्त्यधर्माणः. 2 प्राणहर (री *f*.), जीवितापह, प्राणांतक, मारात्मक, मर्मभेदिन्, अंतकर (री *f*.), प्राणापह, प्राणघ्न (घ्नी *f*.), मरणावह. 3 मर्त्य, मानुष (षी *f*.), मनुष्यधर्मन्; *See* **Human.** 4 अत्यंतदारुण, अतिक्लेशक; 'm. enemy' आमरणांतवैरिन् *m*., बद्ध-बद्ध-वैरः. -**ity,** *s*. मर्त्यता, मरणशीलता, मृत्युवशता, मृत्यु-मरण-धर्मः, कालधर्मः, नश्वरता, अनित्यता. 2 मृत्युः, मरणं, नाशः, जीवितनाशः 3 मनुष्यं, मानुषता -**ly,** *adv*. सप्राणनाशं, ex. by *a*.; 'he was m. wounded' तस्य प्राणहरा व्रणाः संजाताः, भिन्नमर्माऽभूत्.

Mortar, *s*. उलु(लू)खलं; 'm. and pestle' उलूखलमुसले. 2 लेपः, सुधा, चूर्णलेपः.

Mortgage, *s*. आधिः, क्षेत्र-स्थावर-आधिः, भूमिनिक्षेपः, बंधकः, न्यासः. -*v*. *t*. आ-धा 3 U, आधीकृ 8 U, बंधे दा 3 U, (स्थावरधनं) न्यासीकृ. -**ee,** *s*. आधिग्राहकः, आधिबंधक-न्यास-ग्राहिन् *m*. -**or,** *s*. आधातृ *m*., निक्षेप्तृ *m*.

Mortiferous, *a*. मरणावह; *See* **Mortal.**

Mortify, *v*. *t*. अभिभू 1 P, अवमन् c., अपकृष् 1 P, मानं-गर्वं-भंज् 7 P, खंड् 10; *See* **Humble.** 2 निग्रह् 9 P, सं-नि-यम् 1 P, दम् c. (दमयति), वशीकृ 8 U, आप् 5 U, जि 1 P. 3 क्लिश् 9 P, सं-परि-तप् c., आयस् c.; *See* **Afflict.** 4 चैतन्यं नश् c. or हृ c. -*v*. *i*. नश् 4 P. चैतन्यं नश् c. 2 तप् 4 A, तपस्तप् or चर् 1 P, तपस्यति (D.). -**ed,** *a*. अभिभूत, खंडित, आत्त-हृत-भग्न-गर्व, खंडितमान, भग्न-दर्प-मान. 2 दांत, वशीकृत, जित; 'whose passions are m.' जितेंद्रियः, वशिन् *m*., दांतः, वीतकामः, वीतरागः, निःस्पृहः. 3 क्लिष्ट, सव्यथ, पीडित. 4 नष्ट-चैतन्य-मांस, कोथीभूत. -**ication,** *s*. अभिभवः, अवमानः, अपकर्षः, मान or दर्प-भंगः or खंडनं, मानहानि *f*. 2 दमः, निग्रहः, संयमः-मनं, जयः, इंद्रियदमः-जयः; कामविरक्ति *f*., विषयविमुखता, वैराग्यं. 3 तपश्चर्या, तपस्या, कृच्छ्रं. 4 दुःखं, क्लेशः, आयासः, व्यथा. 5 आशाभंगः-नाशः, मनोभंगः. 6 मांसपाकः, मांसकोथः, चैतन्यनाशः. -**ing,** *a*. मानध्वंसिन्, दर्पहारिन्, व्यथावह; क्लेशकर, (री *f*.), संतापक.

Mortise, *s*. काष्ठसंधिः, दारुसीवनं, दारु-काष्ठ-छिद्रं. -*v*. *t*. काष्ठद्वयं सं-धा 3 U.

Mortmain, *s*. अन्यादेयभोगः.

Mortuary, *s*. श्मशानं, परेतभूमि *f*.- वासः.

Mosaic, *a*. नानावर्ण (विध) प्रस्तरखचित, 'm. work' *s*. चित्रकर्मन् *n*.

Mosque, *s*. यावनधर्ममंदिरं, यवनीयं देवतायतनं.

Mosquito, *s*. मशः. मशकः.

Moss, *s*. शैव(वा)लः, शेव(वा)लः-लं, जलनीली-लिका, 'm.-grown' रूढशैवल, शैवलावृत. -**y,** *a*. शैवलवत्, शैवलिन्.

Most, *a*. भूयिष्ठ, अधिकतम, बहु (pl.); प्रायेण सर्व; 'm. people think so' प्रायेण सर्वे (बहवः) एवं मन्यंते. 2 निरतिशय, अत्यधिक, परम, उत्तम; 'for the m. part' भूयिष्ठं, प्रायः, प्रायेण, बहुशः. -*s*. भूयिष्ठ परमभागः, बहुतम-अधिक-भागः, प्रायः, सर्वभागः; बहुतरभागः; 'm. of the spot is green' प्रायशः सा स्थली हरिद्वर्णा; 'to the m. of one's power' यावच्छक्तितः, यावच्छक्यं -*adv*. भूयिष्ठं, परमं, अत्यंतं, अतीव, सु-अति-अत्यंत-in comp.; gen. ex. by super-

lative of adj. 2 अधिकं, सर्वाधिकं (with verbs). -ly, adv. प्रायः, भूयिष्ठं, प्रायशः, भूयसा, बहुशः, बहुधा, सामान्यतः, साधारण्यतः; gen. ex. by भूयिष्ठ affixed to adj.; 'an assembly m. composed of learned men' अभिरूपभूयिष्ठा परिषद् (S. 1).

Mote, s. बिंदुः, अणुः, लवः, त्रसरेणुः, परमाणुः, कणिका; 'the m. thou seest in the eyes of others, but not the beam in thine own' खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति.

Moth, s. शलभः, पतंगः, कीटः.

Mother, s. मातृ f., जननी, अंबा, जनयित्री, प्रसूः, प्रजयित्री, जनी, प्रसविनी; 'm. of offspring' पुत्रवती, सुतिनी, अपत्यवती; 'm.-in-law' श्वश्रूः; 'm. of a hero' वीरसूः-प्रसवा, वीरजननी; 'born of a different m.' भिन्नोदर, अन्योदर, असोदर. -hood, s. मातृत्वं, जननीत्वं, मातृभावः-धर्मः. -less, a. अमातृक, हीन-मृत-मातृक. -ly, a. मातृसदृश (शी f.), मातृ-संबंधिन्-अनुरूप-योग्य, मातृ in comp. -adv. मातृवत्, मातृभावेन, मातृस्थाने भूत्वा.

Motile, a. चल, जंगम.

Motion, s. गति f., गमनं, चलनं, सर्पणं, चरणं. 2 चेष्टा, व्यापारः, अंगविक्षेपः; 'to set in m.' ईर् c., आ-धू 5, 9 U, 6 P, कंप् c. 3 क्षोभः; वेगः, सं-आ-वेगः, मनोविकारः, मनोवृत्तिः वेगः, भावः, वासना, कल्पना. 4 प्रेरणं-णा, प्रोत्साहनं, प्रचोदना. 5 उपन्यासः, उपक्षेपः, कार्योपक्षेपः, सूचना. 6 रेचः, रेचनं-ना, उच्चारः. -v. i. संज्ञां दा 3 U or कृ 8 U, संकेतं कृ. -less, a. निश्चल, निश्चेष्ट, अचल, अचेष्ट, गतिहीन-शून्य, निष्कंप, अस्पंद, स्तब्ध, स्थिर.

Motive, a. चालक, प्रेरक, प्रवर्तक, हेतुक in comp., कारणीभूत. -s. हेतुः, कारणं, निमित्तं, प्रयोजनं, कार्यं, अर्थः, निदानं, निबंधनं, प्रवर्तकं, प्रवृत्ति-निमित्तं-हेतुः; 'without m.s' निष्कारणं, अनिमित्तं, अहेतुकं, निष्प्रयोजनं, अकस्मात्.

Motley, a. चित्रविचित्र, नानाविध-वर्ण, बहुप्रकार, विविध.

Motor, s. चालकः, प्रेरकः.

Mottle, v. t. चित्र् 10, कर्बुरीकृ 8 U. -ed, a. चित्रित, कर्बुरित, कल्माषित.

Motto, s. वाक्यं, वचनं, आदर्शवचनं.

Mould, s. संस्कारः, आकारः, आकृति f., संस्थानं, रूपं; मूर्ति f. 2 मृद् f., मृत्तिका; मृच्चूर्णं. 3 प्रकृति f., कारणं. -v. t. संस्कृ 8 U, घटय् c., आकारं-रूपं-दा 3 U, रचय् c., रच् 10, घट् 10. -y, a. मलिन, मलयुक्त, कलुष, मलीमस (सी f.).

Moulder, v. i. क्षि pass., जॄ 4 P, चूर्णीभू 1 P, अव-सद् 1 P, शनैः नश् 4 P or क्षि pass.

Moult, v. i. पक्षान् पत् c. or मुच् 6 P or c. -ed, a. मुक्त or पतित-पक्ष or पर्ण. -ing, s. पक्ष or पर्ण-पतनं or मोचनं.

Mound, s. चयः-यं, वप्रः, सानुः, आलि f., पिंडः. 2 मृद्राशिः, मृत्तिकाचयः, क्षुद्रपर्वतः, पांसुकूटः, वास्तुः, वल्मीकः-कं.

Mount, v. t. आ-अधि-रुह् 1 P, अधिक्रम् 1 U, 4 P. 2 आरुह् c. (रोपयति), उच्चैः नम् c. (नमयति), उच्चीकृ 8 U, निविश् c. 3 जट् 10 (जटयति); See Inlay. -v. i. (अश्वं, रथं, &c.) आ-अधि-रुह्, अधिक्रम्, अध्यास् 2 A. 2 उच्चैः गम् 1 P or पत् 1 P. -ed, a. आरूढ, आरोपित; 'a m. soldier' तुरंगारूढः सैनिकः, सादिन् m. -ing, s. आरोहः-हणं, आरोपणं.

Mount, Mountain, s. पर्वतः, अद्रिः, गिरिः, शैलः, नगः, अचलः, महीध्रः, धराधरः, धरः, ग्रावन्, शिलोच्चयः, सानुमत्, शिखरिन्, and comp. of भृत् or धर with 'Earth,' q. v; क्ष्माभृत्, महीधरः, क्षितिधरः &c.; 'western m.' अस्तः, अस्ताचलः, चरमक्ष्माभृत्; 'eastern m.' उदयः, उदयगिरिः-पर्वतः; 'hill near a m.' पादः, प्रत्यंतपर्वतः; 'to make m.s out of trifles' अणुमपि पर्वतीकृ 8 U, तिले तालं दृश् 1 P. -a. पर्वतीय, शैल (ली f.), (s.) in comp. -eer, s. पर्वत &c. -निवासिन् m., शैलाटः. -ous, a. शैलमय (यी f.), सपर्वत, पर्वतीय. 2 (Huge) पर्वतप्रमाण.

Mountebank, s. मिथ्या-कूट-वैद्यः, कूटचिकित्सकः.

Mourn, v. शुच्, शोच् 1 P, विलप् 1 P, परिदेव् 1 A, परिदेव् 10 A, रुद् 2 P, आक्रंद् 1 P, अनुशुच् 1 P. See Lament. -er, s. परिदेवकः, विलापिन् m., शोचकः, विलापकृत्. -ful, a. शोकार्त, शोक-दुःख-पूर्ण, दुःखोद्विग्न. 2 शोकावह, शोकजनक, दुःखद, दुःखावह, शोच्य, शोकार्ह. 3 (Of persons) शोकार्त, शोकाकुल, सशोक, खिन्न, दुःखित, वेदनादुःख-अन्वित, उद्विग्नमनस्, खिन्नमनस्, विषण्ण, सखेद. -fully, adv. सशोकं, सखेदं, सदुःखं, सोद्वेगं. -fulness, s. शोकः, दुःखं, उद्वेगः. -ing, s. शोकः, खेदः, विलापः, परिदेवनं, दुःखं, उद्वेगः, आ-,संक्रंदनं, रोदनं; See Grief. 2 आशौचं; 'one should be in m. for 10 days' दशाहमाशौचं चरेत्; 'm.-dress' शोकवेषः, शोकसूचको वेषः.

Mouse, s. मूष (षि) कः, आखुः, उंदुरुः, गिरिकः, वज्रदशनः; 'small kind of mice' गिरिका, बालमूषिका.

Moustache. *See* **Mustache.**

Mouth, *s.* मुखं (in all senses); कूपमुखं, पात्रमुखं, नदीमुखं, &c.; वक्त्रं, वदनं, आननं, आस्यं; तुंडं, लपनं (of animate beings only); 'corner of the m.' सृक्कन् *n.*, सृक्कं, ओष्ठप्रांत:; 'rinsing the m.' आचमनं; 'stop the m.' वाचं स्तंभ् 9 P or c. 2 छिद्रं, रंध्रं, द्वारं, मुखं; 'm.-piece' मुखपात्री; मुखं (fig.). -*v.* मुखर्-उच्चै:-वद् 1 P. 2 चर्व् 1 P, 10; ग्रस् 1 A, भक्ष् 10. **-ful,** *s.* ग्रास:, कवल:, पिंड:, गंडूष: (of water). **-less,** *a.* मुखहीन, निराचन.

Move, *v. i.* चल्-र् 1 P, सृप् 1 P, प्र-वि-°, सृ 1 P, गम् 1 P, या 2 P, इ 1 P. 2 भ्रम् 1, 4 P, परिप्लु 1 A. 3 स्थानांतरं-गृहांतरं गम् or या. 4 चेष्ट् 1 A, स्पंद् 1 A; 'm. on' प्र-वृ, प्र-चल्, प्र-या, प्र-स्था 1 A; 'm. about' परिभ्रम्, इतस्तत: चल्; 'm. off' अप-या, अपक्रम् 1 U, 4 P, अप-सृ-चल्; 'don't m. even a step further' अस्मात्स्थानात्पदमात्रमपि न गंतव्यं (Ka. 147). -*v. t.* चल् c., प्र-वि-चल्°, प्र-वृ c., ईर् c. 2 चरि-,भ्रम् c. (भ्रमयति); स्थानांतरं गम् c. (गमयति). 2 क्षुभ् 1 P, क्षुभ् c., प्लुत् c.; आंदोल् c., धू 5 P or c., प्रक्षुभ् 10, चेष्ट् c., उद्-व-धूल् 10. 3 दयां-करुणां-उत्पद् c., हृदयं स्पृश् 6 P or आर्द्रीकृ 8 U, द्रु c., उपहन् 2 P; आक्षिप् c. 4 उपन्यस् 4 U, उप-क्षिप् 6 P, उप-स्था c. (स्थापयति); 'to be m.-ed' आर्द्रीभू 1 P, (करुणया) द्रु 1 P or द्रवीभू; *See* **Melt, Affect**; 'he appears to be m.-ed' द्रवीभूत इव लक्ष्यते; 'let my presence m. (you)' मामवलोक्यापि आर्द्रीकुरुष्व; 'she was m.-ed to tears' तया द्रवीभूतया सर्वा अश्रूणि व्यसृज्यत; 'he was deeply m. ed by what I said' मम वचसा तस्य चेतसि दृढं पदं चक्रे; 'm. ed with grief' शोकोपहत, दुःखाभिभूत, शोकस्पृष्ट; 'm. a chess-man' शारिं चरि-ची 1 P. -*s.* गमनं, चलनं, सरणं &c.; 'm. at chess' शारि(री)चार:. **-able,** *a.* चल, चर, जंगम, चरिष्णु, चलन-गमन-शील-क्षम, अस्थावर; 'm. and im-m. world' चराचरं विश्वं, अखिलं जगत्. **-ables,** *s.* चरद्रव्याणि, अस्थावरद्रव्यजातं. **-ed,** *a.* चलित, प्रेरित, &c.; 'gently m.' वेल्लित, प्रेंखित, आधूत, चलित, आकंपित, धुत. **-er,** *s.* चालक:, चलन:. 2 उपक्षेपक:, उपन्यासकृत् *m.* 3 प्रवर्तक:, प्रयोजक:, प्रेरक:. **-ing,** *a.* चर, चल, जंगम. 2 चलत्; गामिन्, चारिन्, विसर्पिन्, in comp. 3 हृदयस्पृश्, हृदयग्राहिन्, मर्मस्पृश्-भिद्, हृदयंगम, दयावह, करुणात्मक, हृदयद्रावक. **-ingly,** *adv.* हृदयग्राहितया, हृदयंगमं. **-ment,** *s.* चलनं, गमनं, गति *f.*, स्थानांतरगमनं. 2 व्यापार:, चेष्टा, क्रिया, वृत्ति *f.*, चेष्टितं, प्रवृत्ति *f.*; 'graceful m.' विलास:, विभ्रम:; *See* under **Graceful.** 3 भ्रमणं, भ्रमि:; 'circular m.' मंडलभ्रमणं. 4 क्षोभ:, कंप:. 5 ग्राम:, मूर्च्छना.

Mow, *v. t.* (तृणादि) छिद् 7 P, लू 9 P. दो 4 P, कृत् 6 P. -*s.* तृण-धान्य-राशि:, तृणोत्कर:, धान्यचय:. **-er,** *s.* लावक:, तृणच्छिद् *m.* **-ing,** *s.* तृणच्छेद:, तृणकर्तनं.

Much, *a.* बहु, बहुल, प्रचुर, भूरि, पुष्कल, भूयस्, गाढ, अत्यंत, निर्भर, महत्, अत्यर्थ, अतिरिक्त, उत्कट, अतिमात्र, नितांत, घन, दृढ, भृश; gen. ex. by सु, अति pr., अतिशय in comp. -*s.* बहु *n.* or in comp., बाहुल्यं, बहुभाग:, भूयिष्ठं, भूयिष्ठभाग:; 'talking m.' बहुभाषिन्; 'as m. as' यावत्-तावत्; 'as m. as may lie in one's power' यथाशक्ति, यावच्छक्यं; 'how m.' कियत्; 'so m.', 'this m.' इयत्, एतावत्; तावत् (as correlative of यावत्); 'that m.' तावत्, 'm. more', 'm. less' किमुत, किमु, किंपुन:. -*adv.* बहु, भृशं, अत्यंतं, भूरि, गाढं, निर्भरं, नितांतं, अतिमात्रं, सुतरां, अत्यर्थं, अति-सु- pr.; *See* **Exceedingly.**

Mucilage, *s.* मेदस् *n.*, मज्जा, वसा. 2 श्लेष्मन् *m.*, पिच्छलवस्तु. **-Mucilaginous,** *a.* पिच्छल, स्निग्ध. 2 श्लेष्मल-ण.

Muck, *s.* पुरीषं; *See* **Dung.** 2 मलं, कर्दम:, कल्कं, अमेध्यं, कलुषं; 'm.-heap, or-hill' मलराशि:-संचय:, अवकरनिकर:; 'm.-sweat' अतिस्वेद:, अत्यंतघर्म:, 'm.-worm' पंकज:, कीट:. -*v. t.* मलेन लिप् 6 P. **-y,** *a.* मलिन, समल, पंकिल, अमेध्य.

Mucus, *s.* श्लेष्मन् *m.*, मलं, इंद्रियमल:; 'm. of the nose' सिंघाणं, सिंहाण-णं, नासामलं; 'm. of the throat' कफ:, श्लेष्मा; 'm. of the bowels' आम:; 'm. of the urethra' पूयं, शुक्र:. **-Mucous, -Muculent,** *a.* पिच्छल, श्लेष्मल-ण, कफमय. 2 श्लेष्म-कफ-कर (री *f.*).

Mud, *s.* पंक:-कं, कर्दम:, जंबाल:-लं, शाद:, निषद्वर:. **-dy,** *a.* पंकिल, सपंक, पंकदूषित सकर्दम, मलिन, समल, मलीमस; 'm.-headed' स्थूल-जड-बुद्धि, मंदबुद्धि. **-Muddle,** *v. t.* पंकिलयति-कलुषयति-आविलयति (D.), दुष् c. (दूषयति), मलिनीकृ 8 U, आविलीकृ. 2 (Fig.) आकुलयति (D.), आकुलीकृ, ईषत् मुह् c or मद् c.

Muff, *s.* लोममयं हस्तत्राणं. 2 मूढ:, मंदधी:.

Muffle, *v. t.* (वस्त्रेण) अवगुंठ् 10, परि-आ-वेष्ट् 1 A or c., आच्छद् 10, अपवृ 5 U, बंध् 9 P, प्रावृ 5 U; *See* **Cover.** **-er,** *s.* आच्छादनं, अवगुंठनं, मुखाच्छादनं.

Mug, *s.* पानपात्रं-भाजनं, कंसः, जलपात्रं-भाजनं.
Muggy, Muggish, *a.* क्लिन्न, क्लिन्ननिर्वात.
Mulberry, *s.* तु(तू)दः, यूपः, क्रमुकः, ब्रह्मण्यः, ब्रह्मदारु *n.*
Mulct, *s.* दंडः, अर्थ-धन-दंडः. –*v. t.* दंडू 10, दंडं दा c. (दापयति).
Mule, *s.* अश्वतरः, वेश(स)रः, वेगसरः; *See* **Donkey** also; 'm.-driver (muleteer)' वेसरपालः, अश्वतरपालः.
Muliebrity, *s.* स्त्रीभावः, स्त्रीत्वं, नारीत्वं.
Mull, *v. t.* वास् 10, भू c.
Muller, *s.* शिला, शिलापट्टः, पेषणशिला, पेषणि-णी *f.*
Mulligrubs, *s.* अंत्रशूलं-वेदना.
Multangular, *a.* बहुकोण, अनेकास्र.
Multifarious, *a.* विविध, बहुप्रकार-विध, नाना-विध-प्रकार, नाना-बहु-रूप, अनेक, बहु.
Multiform, *a.* बहु or नाना-रूप, नाना or बहु-प्रकार or विध. –**ity,** *s.* बहुविधता, अनेक-रूपता, नानारूपत्वं.
Multilateral, *a.* अनेकभुज-पार्श्व.
Multilineal, *a.* बहुरेख.
Multiparous, *a.* बहुप्रसव, बह्वपत्य, बहुप्रज.
Multiped, *a.* बहुपद्.
Multiple, *s.* आघारः.
Multiplicity, *s.* बाहुल्यं, अनेकत्वं, प्राचुर्यं, प्रभूतत्वं; 'm. of business' अनेककार्य-व्यापृतत्वं, कार्यवैचित्र्यं.
Multiply, *v. t.* गुणयति (D.), हन् 2 P or c. (घातयति), आ-नि-°, पूर् 10; 'm. ing 4 by 3 we get 12' त्रिगुणिताः-त्रिभि-राहताः-चत्वारः द्वादश संपद्यंते; त्रिघ्नेषु चतुर्षु द्वादश फलं. **2** वृध् c., उप-चि 5 U, बहुली-प्रचुरी-कृ 8 U. –*v. i.* वृध् 1 A, स्फाय् 1 A, प्र-उप-चि pass., बहुली-भू 1 P; *See* **Increase. 2** अपत्यानि उत्पद् c., संततिं जन् c. (जनयति) –**ed,** *a.* गुणित, हत, गुण-घ्न in comp. **2** वर्धित, वर्धितसंख्य. –**ier,** –**icator,** *s.* गुणकः, गुणकांकः. –**ication,** गुणनं, हननं, आघातः, अभ्यासः; 'cross m.' वज्राभ्यासः, वज्राघातः; 'duodecimal m.' गोमूत्रिका. **2** वर्धनं, वृद्धि *f.*, उप-चयः. –**icative,** *a.* गुणक. –**Multiplicand,** *s.* गुण्यः, गुण्यांकः.
Multipotent, *a.* बहुकार्यक्षम.
Multiradiate, *a.* बहुकिरण.
Multisonous, *a.* बहुस्वन-ध्वनि-नाद्.
Multitude, *s.* समूहः, समुच्चयः, गणः, निवहः, संघातः, समुदा(द)यः, समाहारः, ओघः, प्र-नि-सं-चयः, स्तोमः, निकरः, समवायः, चयः, संहति *f.*, कदंबकं, वृंदं, संग्रहः, समाजः, व्यूहः, संदोहः, विसरः, व्रजः, व्रातः, वारः, निकुरंबं; वर्गः (of similar things); संघः, सार्थः (of animals); कुलं, यूथः-थं (of lower animals); समजः (of beasts); निकायः; पुंजः, राशिः, उत्करः, कूटः-टं (of corn &c.); जालं, मंडलं, पूगः, ग्रामः in comp. **2** जन or लोक-संमर्दः-निवहः-संघः, जनमेलकः, जनता, लोकग्रामः. **3** बाहुल्यं, बहुत्वं.
Multitudinous, *a.* बहु, बहुल, प्रचुर; *See* **Many.**
Multiversant, *a.* बहुरूपधारिन्.
Multocular, *a.* बहुनेत्र-लोचन.
Mum, *a.* निःशब्द, अनालाप. –*interj.* तूष्णीं भव, निःशब्दो भव, वाचं यच्छ.
Mumble, *v.* अस्पष्टं वद् 1 P or उच्चर् c., अव्यक्तं उदीर् c., नीचैः वद्, जप् 1 P. –**ingly,** *adv.* अस्पष्टवाचा, अव्यक्तगिरा.
–**mmer,** *s.* दांभिकः, छद्मवेशिन् *m.* –**y,** *s.* विडंबनं-ना, माया, छलं, व्याजः, छद्मवेशः, भंडता; *See* **Trick.**
Mummy, *s.* रक्षितं मृतशरीरं.
Mump, *v.* अस्पष्टं वद् 1 P or उच्चर् c., **2** चर्व् 1 P, 10. **3 Cheat,** q. v.
Munch, *v. t.* चर्व् 1 P, 10.
Mundane, *a.* सांसारिक-लौकिक-ऐहिक-ऐह-लौकिक- (की *f.*): 'm. existence' संसारः, भवः, संसृति *f.*, लोक-जीव-यात्रा.
Mungoose, *s.* नकुलः, बभ्रुः, अंगूषः.
Municipal, *a.* नगरीय, नगर-पुर- in comp. –**ity,** *s.* नगरपालिका, ग्रामावेक्षिका.
Munificent, *a.* उदार, वदान्य, दानशौंड, दान-त्याग-शील. –**ly,** *adv.* उदारवत्, सौदार्यं. –**Munificence,** *s.* औदार्यं, वदान्यता, अतित्यागः, दानशौंडता; *See* **Generous,-ness.**
Muniment, *s.* दुर्गं, कोटः.
Munition, *s.* युद्धसामग्री-सज्जा.
Mural, *a.* भित्ति-प्राकार-संबंधिन्.
Murder, *s.* (सद्वेषं) वधः, हत्या, घातः, हननं, मृदनं, हिंसा. –*v. t.* हन् 2 P or c. (घातयति), व्यापद् c. –**er,** *s.* घातकः, हंतृ *m.*, हन् in comp., वधकारिन् *m.*, वधोद्यतः, मारकः. –**ous,** *a.* हंतुकाम, जिघांसु, हिंसा-बुद्धि, वधोद्यत, वधैषिन्. **2** निष्ठुर, दारुण, अतिघोर. **3** घातक, प्राणांतक, जीवितनाशिन्. **4** मारात्मक, आत्ययिक (की *f.*).
Murk,-y, *See* **Dark.**
Murmur, *s.* मंद्रध्वनिः-स्वनः, मर्मरध्वनिः, कल-रवः-स्वनः-रुतं, कलकलः गुंजितं, गंभीरनादः; 'm. of applause' प्रणादः. **2** अंतर्-गूढ-विलापः, असंतोषध्वनिः. –*v. i.* असंतोषण-सविषादं-सनिर्वेदं-विलप् 1 P or परि-देव् 1 A or परिदिव् 10 A **2** गुंज् 1 P, कल-मंद्रं-गंभीरं-रु 2 P. **3** जप् 1 P, नीचैः वद् 1 P. –**er,** *s.* असंतुष्टजनः, सदाविलापिन् *m.*
Murrain, *s.* मारी, महामारी.
Muscle, *s.* स्नायु *f.*: मांसपेशी, कसा, वस्नसा, पेशी, शिरा. **2** शंबूकः. –**Muscular.**

-**Musculous**, *a*. स्नायुसंबंधिन्. 2 मांसल, दृढांग (गी *f*.), उपचितमात्र.

Muse, *v. i*. ध्यै 1 P, चिंत् 10, विमृश् 6 P, विचर् c., *See* **Meditate**. -*s*. ध्यानं, चिंता. 2 वाग्देवी, सरस्वती, विद्याधिष्ठात्री, विद्यादेवता. -**ful**, *a*. चिंता or ध्यान-पर-शील-निष्ठ.

Museum, *s*. कौतुकागारं, दुर्लभवस्तुसंग्रहः.

Mushroom, *s*. छत्रं, छत्रकः; *See* **Fungus**. -*a*. अचिरस्थायिन्, क्षणध्वंसिन्, उत्पन्नैव विलीयमान.

Music, *s*. गीतं, संगीतं, संगीत or वाद्य-विद्या or शास्त्रं (science of m). 2 (Melody) तालैक्यं, स्वरानुपूर्व्यं, सुस्वनः-स्वरः, माधुर्यं; तौर्यं, वाद्यघोषः; 'vocal m.' संगीतं; 'instrumental m.' वादनं; 'set to m.' स्वर-ताल-बद्ध; 'm.-room' संगीतशाला; 'fond of m.' नादलुब्ध. -**al**, *a*. संगीतविषयक, गानीय, (*s*.) in comp. 2 सुस्वर, सुश्राव्य; *See* **Melodious**. 3 संगीत-गान-प्रिय, नादप्रिय-लुब्ध-आसक्त, वादनशील-आसक्त; 'm. entertainment' गानोत्सवः; 'm. instrument' वादित्रं, वाद्यं; 'm. glasses' जलतरंगः. -**ally**, *adv*. सुस्वरं, संगीत शास्त्रानुरूपं. -**ian**, *s*. गायकः, गातृ *m*., गाथकः. 2 वादकः, वादित्रकुशलः, संगीतज्ञः, सुस्वराभिज्ञः.

Musk, *s*. कस्तूरी, कस्तूरिका, मृगनाभिः, मृगमदः, नाभि *m. f*., गंधधूलि *f*., वातामोदा, अंडजा; 'm.-deer' गंधमृगः, कस्तूरीमृगः; 'm.-rat' गंधमूषकः, गंधाखुः. -**y**, *a*. कस्तूरीयुक्त, मृगनाभिगंधि, कस्तूरीवासित.

Musket, *s*. आग्नेयनालि-ली *f*. गुलिकाप्रक्षेपिणी.

Muslin, *a*. सूक्ष्मवस्त्रं, सूक्ष्मांशुकं, अंशुकं.

Must, *v*. ex. by pot. pass. part. with or without अवश्यं, नियतं, नूनं; 'I m. worship god' (अवश्यं) मयेश्वरः पूजनीयः, 'he m. have now come home' अधुना तेन गृहमागतेन भवितव्यं; oft. by अर्ह् 1 P: 'he m. be honoured' मानमर्हत्येव; 'it m. be so' एवं खलु तत्स्यात्, एवं नाम. -*s*. द्राक्षारसः. -*v. i*. विरसीभू 1 P. -**y**, *a*. विरस, निःसार; दुर्गंध.

Mustaches, Mustachio, *s*. श्मश्रु *n*., शुंफः, ओष्ठलोमन् *n*.

Mustard, *s*. सर्षपः, तै(तु)तुभः, कदंबकः; 'black m.' कृष्णिका, राजिका, क्षवः, क्षुता(धा)भिजननः, आसुरी, राजसर्षपः; 'white m.' सिद्धार्थः-र्थकः.

Muster, *v. t*. संग्रह् 9 P, समा-इ 1 P, समानी 1 P, सं-ऊह् 1 U; समाह्वे 1 P, एकीकृ 8 U, संगम् c., (गमयति). 2 (सैनिकान्) परिसं-ख्या 2 P or परिगण् 10. एकत्र समानी. -*v. i*. सं-इ 2 P, संमिल् 6 P, संगम् 1 A; *See* **Assemble**; 'm.-roll' नामावलि-ली *f*., परिसंख्या, परिगणना.

Mutable, *a*. विकारवत्, अस्थिर, परिवर्तनीय, विकारशील, अनियत, अनवस्थित, अस्थायिन्, स्थायिन्. 2 लोल, चंचल, तरल; *See* **Fickle**. -**ness**, -**Mutability**, *s*. अस्थैर्यं, क्षयिता, विकारशीलता, परिवृत्तिक्षमता, अनवस्थिति *f*. 2 लौल्यं, चांचल्यं, तरलता. -**Mutation**, *s*. परिणामः, विकृति *f*., विकारः, विक्रिया, स्थिति-अवस्था-भेदः.

Mute, *a*. मूक, जड, जडवाच्, वाक्शून्य, अवाच्, वाणीहीन, निःशब्द, मुद्रितमुख; 'm. with wonder' आश्चर्यजडीकृत. -*s*. मूकजनः, मूकः. 2 पक्षिपुरीषं. -**ly**, *adv*. निःशब्दं, मूकवत्, जडवत्. -**ness**, *s*. मूकता, जाड्यं, वागभावः, वाक्स्तंभः, मौन-मूक-भावः.

Mutilate, *v. t*. व्यंगीकृ 8 U, विकलीकृ; (अंगानि) खंड् 10, व्यव-च्छिद् 7 P, कृत् 6 P. -**ed**, *a*. विकलांग (गी *f*.), क्षतविक्षत, छिन्नभिन्न, खंडितांग, खंडितविग्रह, नष्टेंद्रिय. -**ion**, *s*. व्यंगीकरणं, व्यवच्छेदः-दनं, खंडनं, अंगकर्तनं. 2 न्यूनांगता, व्यंगता, वैकल्यं.

Mutiny, *s*. सैन्यद्रोहः- अपरागः-विरक्ति *f*., क्षोभः- प्रकोपः, संक्षोभः, व्युत्थानं; 'let him raise a m. in Jambudwipa' जंबुद्वीपे कोपं जनयतु (H. 3). -*v. i*. अभि-द्रुह् 4 P, प्रकोपं दृश् c., विरागं दृश् c., क्षुभ् 4 P, व्युत्था 1 P, शासनं लंघ् 1 A, 10. -**eer**, *s*. प्रकोपकारिन्, आज्ञालंघिन्, अभि-वि-द्रोहिन्, द्रोह-क्षोभ-कारिन् all *m*. -**ous**, *a*. अंतःप्रकोपकर (री *f*.), आज्ञालंघिन्, क्षोभ-प्रकोपकारिन्; प्रतीप, अवश, अनायत्त, दुःशास्य.

Mutter, *v*. अस्फुटं-अस्पष्टं वद् 1 P or जल्प् 1 P, अव्यक्तं उच्चर् c., नीचैः वद्; 'm. prayers' जप् 1 P. 2 गर्ज् 1 P, स्तन् 1 P, गंभीरं स्वन् 1 P. -*s*. -**ing**, *s*. अस्पष्टोच्चारणं, अव्यक्तभाषणं, उपांशुवादः-भाषितं. 2 जपः, जाप्यं, स्वाध्यायः. 3 गर्जितं, स्तनितं, निर्घोषः. -**er**, *s*. अस्फुटवादिन् *m*., उपांशुवादिन् *m*. -**ingly**, *adv*. उपांशु, नीचैः, अस्पष्टं, अव्यक्तं.

Mutton, *s*. मेषमांसं, अविमांसं.

Mutual, *a*. परस्पर, अन्योन्य, मिथः, इतरेतर, in comp.; 'm. help' अन्योन्यसाहाय्यं; oft. by प्रति pr.; 'm. obligation' प्रत्युपकारः; प्रतिघातः, प्रत्यभियोगः, &c. -**ity**, *s*. परस्परयोगः-भावः-संबंधः व्यतिकरः, अन्योन्याश्रयः, व्यतिहारः. -**ly**, *adv*. परस्परं, अन्योन्यं, मिथः, इतरेतरं (*a*) in comp.

Muzzle, *s*. घोणा. 2 मुखं, प्रवेशः; छिद्रं, द्वारं. 3 मुखबंधनी-रोधनी. -*v*. मुखं बंध् 9 P or रुध् 7 U

Myography, *s*. स्नायुवर्णनं.

Myope, *s.* अल्पदृश् *m.*, अदीर्घदृष्टिः.
Myriad, *s.* अयुतं, दशसहस्रं.
Myrmidon, *s.* परिचरः, क्रूरपरिचरः.
Myrobalan, *s.* आमलकः-की-कं, तिष्यफला, अमृता, वयस्था; (beleric m.) विभीतकः-की-कं, अक्षः, तुषः, कर्षफलः, भूतावासः, कलिद्रुमः; 'yellow m.' अभया, अव्यथा, पथ्या, कायस्था, पूतना, अमृता, हरीतकी, हैमवती, चेतकी, श्रेयसी, शिवा.
Myrrh, *s.* बोलः, गंधरसः, रसगंधः, प्राणः, पिंडः, गोपरसः, गोपः, रसः, बोलः.
Mystery, *s.* रहस्यं, नि-,गूढं, गुह्यं, गूढार्थः, गूढतत्त्वं, गहनवस्तु-विषयः. **-ious**, *a.* नि-, गूढ, गहन, रहस्य, गुह्य, गुप्त, गूढार्थ, दुरर्थ, दुर्ज्ञेय, दुर्बोध, अव्यक्त, अस्पष्ट; 'm. are the ways of Fate' कर्मणो गहना गतिः; 'a m. person' अज्ञातकर्मा पुरुषः, गूढचरित्रो नरः. **-iously**, *adv.* गहनं, गूढं. **-iousness**, *s.* गूढता, गहनता, दुर्बोधता.
Mystic,-al, *a.* गूढ, गुप्त, गहन; *See* **Mysterious**. **-ally**, *adv.* गूढं, गहनं. **-ism,-ness.** *s.* गूढता, गहनता. **-Mystify**, *v. t.* गहनीकृ 8 U, गूढीकृ.
Myth, Mythe, *s.* पुराणं, पुरावृत्तं, पुरातन-पुरावृत्त-कथा, पुरावृत्ताख्यानं, पौराणिकी कथा. 2 कल्पितकथा, कूटार्थकथा. **-ic,-ical**, *a.* पौराणिक (की *f.*), पुरातनकथित-वृत्त. 2 काल्पनिक (की *f.*), कूटार्थ. **-Mythology**, *s.* पुराणं, इतिहासः, पुरातनज्ञानं, देवताख्यानं. **-ical**, *a.* पौराणिक-ऐतिहासिक (की *f.*); *See* above. **-ist**, *s.* पुराणविद् *m.*, पुराणवित्, इतिहासज्ञः.

N.

Nab, *v. t.* अकस्मात् धृ 1 P or ग्रह् 9 U.
Nacre, Naker, *s.* मुक्तास्फोटः, शुक्तिपुटं.
Nadir, *s.* अधोबिंदुः.
Nag, *s.* अश्वकः, घोटकः; *See* **Horse**. **-v. t.** क्लिश् 9 P, अर्द् 1 P.
Naiad, *s.* जलदेवता, अप्सरस् *f.*
Nail, *s.* नखः-खं, नखरः-रं, करजः, पुनर्भवः, पुनर्नवः; 'to fight tooth and n.' अत्यावेशेन (नखानखि) विवद् 1 A or युध् 4 A. 2 कीलकः, कीलः, शंकुः लोहकीलः, शंकुः. **-v. t.** कील् 10, (सा नखेनापि कीलितेव Mal. 5), कीलैः बंध् 9 P; 'n. ed to the spot' तत्स्थानकीलित.
Naive, *a.* सरल, ऋजु, निर्व्याज, निर्व्यलीक, भद्र, सरलमति, मुग्ध; *See* **Frank**. **-ly**, *adv.* निर्व्याजं, मुग्धतया, सरलेन. **-Naivete**, *s.* सारल्यं, ऋजुत्वं, मौग्ध्यं, अव्याजता, अव्याजः, आर्जवं, निर्व्याजता.
Naked, *a.* नग्न, विवस्त्र, निर् or अ-वस्त्र or वसन, विवसन, विवासस्, अपरिच्छद, दिग्वसन, दिगंबर, वस्त्र or वसन-हीन-रहित-शून्य, विवृत, अनावृत, अनाच्छादित. 2 अरक्ष्य, असंवृत, अदूषित. 3 केवल, अनावृत, शुद्ध, मात्र in comp. 4 स्पष्ट, प्रकाश, स्फुट; 'by the n. eye' नेत्रमात्रेण; 'a n. woman' नग्ना, कोटवी; 'he would not have left me n. to my enemies' शत्रुभ्यः शत्रुवशं न मां त्याक्ष्यत्. **-ly**, *adv.* नग्नवत्, अपरिच्छदं; केवलं, स्पष्टं. **-ness**, *s.* नग्नता, नग्नभावः; अनावृतत्वं.
Name, *s.* नामन् *n.*, नामधेयं; अभिधा, अभिधानं, आख्या, संज्ञा, अभिधेयं, आह्वयः, आह्वा, उपाधिः, लक्षणं, व्यपदेशः; 'do you know them by n.' अपि ज्ञायंते ते नामधेयतः; 'I shall ask his mother's n.' अस्य मातरं नामतः पृच्छेयं (S. 7); 'call by n.' नाम ग्रह् 9 U, संबुध् c., नाम्ना आह्वे 1 P; 'calling by n.' नामग्रहः-हणं, संबोधनं; 'he calls me by my n.' नामग्राहं मामाह्वयति 'family n.' उपनाम, कुलनाम; 'in one's n.' वचनेन, वचनात्; 'say to the king in my n.' वाच्यस्त्वया मद्वचनात्स राजा (R. xiv. 61); 'what is the n. of the sage' किंनामधेयोऽसौ मुनिः; 'in the n. of' (in oaths) शब्दीकृत्य. 2 ख्याति, कीर्ति-ख्याति-प्रतिष्ठि-विश्रुति- *f.*, प्र-,वि-,ख्यातिः, यशस् *n.*; 'who has made a n.' लब्धप्रतिष्ठः; 'good n.' सुकीर्तिः, सुख्यातिः; 'bad n.' अप-or-अकीर्तिः, दुष्कीर्तिः, अख्याति. **-v. t.** अभि-धा 3 U, आह्वे 1 P, आ-ख्या 2 P, आ-व-चक्ष् 2 A, उद्घुष् 1 P, व्यप-दिश् 6 P, संज्ञां-नाम-कृ 8 U (with gen.); *See* **Call**; 'hence his father n. ed his son Aja after the Creator' अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार (R. v. 36). 2 नाम्ना निर्दिश् 6 P or उद्-आ-हृ, नामतः कथ् 10 or वच् 2 P or ब्रू 2 U or कीर्त् 10, नाम ग्रह्; *See* **Tell** also. **-ed**, 'by name' *a.* अभिहित, कथित, संज्ञित, कीर्तित, उदाहृत, व्यपदिष्ट gen. ex. by नाम *ind.*, or by (*s.*) in comp.; 'a son n. Rāma' रामनामा or रामो नाम or रामसंज्ञः पुत्रः. 2 नामकथित, कृत-उक्त-नाम-नामन्. **-ing**, *s.* नामकरणं, नामनिर्देशः-ग्रहणं. **-less**, *a.* अनामक, नामहीन, अप्रसिद्ध. **-ly**, *adv.* यथा, नाम, ex. by तद्यथा, (त्रिरभ्यसेत् ... तद्यथा अनुज्ञातो विवाहश्च Ms. 3). **-Namesake**, *s.* एक-सम-नामकः, एकनामधारिन् *m.*, सनामन् *m.*

Nap, *s.* अल्प-स्वल्प-निद्रा, अर्धनिद्रा. 2 रो-(लो) मन् *n.* 3 [illegible]. —*v. i.*, 'take a n.' अल्पकालमात्रं स्वप् 2 P. **—less**, *a.* लोम-हीन. **—py**, *a.* लोमश, लोममय (यी *f.*). 2 निद्रालु. 3 स्वाप or निद्रा-कारिन् or जनक.

Nape, *s.* मन्या, [illegible], अवटुः, कृकाटिका.

Napkin, *s.* [illegible]-मार्जनवस्त्रं, [illegible].

Narcotic, *a.* निद्रा or स्वाप-कारिन् or जनन (नी *f.*). —*s.* निद्राकरं औषधं, निद्रौषधं.

Nard, *s.* [illegible], जटामांसी, तपस्विनी, लोमशा, मिसी (षी).

Narrate, *v. t.* वर्ण् 10, परि-कृत् 10, कथ् 10, आख्या 2 P, नि-वद्-विद् *c.*, अभि-धा 3 U, व्याहृ 1 P, वद् 1 P, चक्ष् 2 A; *See* **Tell.** **—ion**, *s.* कीर्तनं, कथनं, वर्णनं, आख्यानं, निवेदनं. 2 कथा; *See* below. **—ive**, *s.* कथा, आ-उप-ख्यानं, आख्यायिका, वृत्तांतः, चरितं, कथाप्रबंधः, इतिहासः. —*a.* कथासंबं-धिन्, कथा in comp., [illegible]. **—or**, *s.* निवेदकः, कथकः.

Narrow, *a.* अविस्तृत, अविस्तीर्ण, सं-नि-बद्ध, संकट, संबाध, संकु(को)चित, संवृत, अपृथु, अविपुल, अनायत, निरायत, अल्पपरि-माण, [illegible]. 2 अल्प, परि-मित, संयत, नियत, नियद्ध; *See* **Limited**; 'a n. pass' संकटं, संबाधः, संकटमार्गः. 3 (Fig.) क्षुद्र, अल्प, लघु, कृपण, [illegible]; 'of n. views', 'n. minded' क्षुद्रमनस्, लघुचेतस्, कृपण-बुद्धि-धी-मति-चेतस्, अनुदारशील. 4 सूक्ष्म, [illegible], निपुण, सुविज्ञ. —*v. t.* संक्षिप् 6 P, संकुच् 1 P, संबाध् 1 A, संरुह् 1 P, संवृ 5 U, [illegible] *c.*, परि-मा 3 A, 2 P, संनि-यम् 1 P; *See* **Limit.** —*v. i.* Pass. of roots above. **—ly**, *adv.* अविस्तृतं, [illegible], [illegible], अनायतं. 2 [illegible], [illegible], [illegible], [illegible]; by [illegible] in comp; 'he n. escaped being foiled' [illegible]. 3 सूक्ष्मं, निपुणं. **—ness**, *s.* अविस्तृति *f.*, संकोचः, [illegible], [illegible], [illegible], कार्पण्यं, दैन्यं, अनुदारता, &c.

Nasal, *a.* आनुनासिक (की *f.*), नस्य, ना-सिक्य, [illegible]. —*s.* अनुनासिकं.

Nascent, *a.* प्रादुर्भवत्, [illegible].

Nasty, *a.* मलिन, अशुद्ध, [illegible], अपवित्र, [illegible]; कुत्सित, गर्हित, [illegible]. **—ily**, *adv.* मलिनं, कुत्सितं. **—iness**, *s.* मालिन्यं, मलं, [illegible], अपवित्रता.

Natal, *a.* जन्म in comp.; 'n. country' जन्मभूः.

Natant, *a.* प्लव, [illegible].

Nation, *s.* वर्षं, जनपदः, देशः, विषयः; (people) लोकः, जनाः, प्रजाः, जनता, जनः, लोकः, देशस्थ-लोकः, देशवासिनः. **—al**, *a.* देशीय, दैशिक (की *f.*), देश्य, राष्ट्रीय, देश in comp.; 'n. custom' देशाचारः; 'n. law' देशधर्मः; 'n. calamity' ज-नक्षयः, जनपदोपद्रवः. 2 देशाभिमानिन्. 3 [illegible]. [illegible] (णी *f.*), सर्वजनीन; *See* **General.** **—ality**, *s.* स्वदेशाभिमानः. 2 देशीयता, देशोद्भवता. **—ally**, *adv.* [illegible], [illegible].

Native, *a.* देशज, देशीय, देशोद्भव, स्वदेशो-त्पन्न. 2 सहज, अकृत्रिम, नैसर्गिक (की *f.*), स्वाभाविक; *See* **Natural.** 3 जन्मजात, जन्म-सिद्ध, जन्म-ज in comp.; 'n. country' जन्मभूमि *f.* -देशः, स्वविषयः-राष्ट्रं; 'n. place' जन्मस्थानं, उत्पत्तिस्थानं. —*s.* देश-वासिन् *m.*, देशजः, देशोद्भवः, देशीयजनः-लोकः. **—ity**, *s.* उत्पत्ति *f.*, संभवः, उद्भवः, जनि *f.* 2 जन्मपत्रिका, जातकं; 'cast one's n.' जातकं निरूप् 10; 'star at one's n.' जन्मनक्षत्रं; 'name given at one's n.' जन्मनाम.

Natron, *s.* सर्जि *f.*, सर्जिका, सर्जिकाक्षारः, कापोतः, [illegible].

Natty, *a.* शोभन, परिष्कृत, सुवेश, [illegible].

Nature, *s.* सृष्टि *f.*, जगत् *n.*, भूमंडलं, विश्वं, ब्रह्मांडं, सर्गः. 2 सर्गः, रीति *f.*, क्रमः, विधिः, नियमः, धर्मः, सृष्टिक्रमः. 3 प्रकृति *f.*, माया, शक्ति *f.*, [illegible], आदिशक्तिः-माया, प्रधानं (according to Sānkhyas). 4 प्रकारः, धर्मः, जाति *f.*, रीतिः, विध, in comp. 5 भावः, प्रकृतिः, स्वभावः, निसर्गः, धर्मः, तत्त्वं, सत्त्वं, गुणः, प्रकृति-निसर्ग-जाति-स्वभावः, संसिद्धि *f.*, स्वरूपं, स्वधर्मः, शीलं. 6 स्वभाव- *r.* प्रकृति-गुणः or धर्मः; 'properties of n.' गुणत्रयं (सत्त्वं, रजः, तमः); 'good n.' सद्भावः, सुशीलं, सौजन्यं; 'of this n.' एवंविध; 'by n.' प्रकृत्या, [illegible], स्वभावतः, [illegible]; 'blind by n.' जन्मांध, जात्यंध, प्रकृत्यंध; 'functions of n.' देह-धर्माः. **—ed**, *a.* स्वभाव, शील, प्रकृति in comp. **—Natural**, *a.* स्वाभाविक-नैस-र्गिक-सांसिद्धिक-प्राकृतिक-स्वाभाविक-[illegible] (की *f.*), सहज, स्वभाव-निसर्ग-ज, स्वभाव-प्रकृति-सिद्ध, स्व, निज, [illegible], [illegible], प्राकृतिक; 'n. enemy' [illegible], [illegible]; 'n. enmity' [illegible] विरोधः; oft. ex. by (*s.*); [illegible] (S. 5) 'it is n. with the benevo-lent.' 2 कोमल, [illegible], [illegible], [illegible]. 3 स्वभावानुरूप, [illegible], प्रकृत्यनु-सारिन्, [illegible]. 4 अकृत्रिम, [illegible], [illegible], [illegible]; 'n. cavity' [illegible]; 'n. loveliness' [illegible]. 5 [illegible], [illegible], [illegible] 6 (Child) [illegible], [illegible] (की *f.*), जारज, [illegible], [illegible]; *See* **Illegitimate.** 7 सत्य, यथार्थ, [illegible], अकृत्रिम, [illegible]. 8 [illegible]; 'n.

death ' यथाकालं मरणं; 'n. day' सावनदिनं; 'n. form' स्वरूपं; ' n. disposition ' स्वभावः, जन्मस्वभावः; 'n. history' जडाजडशास्त्रं, स्थावरजंगमशास्त्रं; 'n. philosophy' पदार्थविज्ञानं; ' n. to ' सुलभ; ' levity n. to mortals' मानुषतासुलभो लघिमा (Ka. 134). -s. मूढः, मूर्खः, जडः. -ist, s. पदार्थज्ञानज्ञः, पदार्थविज्ञानिन् m. -ize, v. t. अभ्यस् 4 U; See **Familiarize. 2** देशीय-a. कृ 8 U. -ly, adv. प्रकृत्या, निसर्गेण, स्वभावतः, स्वभावेन, निसर्गतः, जात्या, (s.) in comp; 'n. charming ' निसर्गमधुर, प्रकृतिसुभग, अव्याजसुंदर-मनोहर, &c. **2** यथाक्रमं, अनुलोमं, सृष्टिक्रमानुसारेण. **3** अकृत्रिमं, अक्लिष्टं, अयत्नतः, सहजशक्त्या-गत्या. **4** स्वतः, स्वयं, अंतःप्रवृत्त्या, अबलात्, सहजावबोधेन. **5** अवश्यं, निर्विवादं, नियतं, अनायासेनैव; नूनं, खलु. -ness, s. सहजत्वं, अकृतकता, याथार्थ्यं, &c.

Naught, s. न किमपि, न किंचित्-किंचन. **2** शून्यं, खं; ' set at n. ' अव-ज्ञा 9 U, तृणीकृ 8 U; See **Contemn, Defy.**-adv. न किमपि, न किंचिदपि, न ईषदपि-स्तोकमपि. -a. असार, निर्गुण.

Naughty, a. दुष्ट, उपद्राविन्, दुर्वृत्त, प्रतीप, अविनेय, अवश्य, हिंसाशील, अपकारप्रिय; See **Mischievous.-ily,** adv. प्रतीपं, दुष्टभावेन. -iness, s. दुर्वृत्तता, प्रतीपता.

Naumachy, s. नौयुद्धं.

Nausea, s. वमनं, उत्क्लेदः, वमनेच्छा. **2** वैकृतं, बीभत्सः, कुत्सा, घृणा, निर्वेदः. -**Nauseate,** v. i. वम् desid. (विवमिषति). -v. t., Abhor, q. v.-**Nauseous,** a. बीभत्सावह, बीभत्स, निर्वेदप्रद, गर्हित, कुत्सित. **2** वमनोत्पादिन्.

Nautic,-al, a. नाविक (की f.), नौ in comp.

Naval, a. समुद्र in comp., नाव्य, नाविक. **2** नौकात्मक, नौरूप.

Nave, s. नाभि-भी f., पिंडि-डी f., पिंडिका. **2** (देवालयस्य) मध्यभागः.

Navel, s. नाभि-भी f., तुंदः-दि-दी f., तुंदिका, उदरावर्तः; ' hollow of the n ' नाभ्यावर्तः; ' having a protuberant n. ' तुंदिन्, तुंदिल-भ, तुंदवत्; 'n.-string' नालः, नाभिनालः.

Navigable, a. नाव्य, नौतार्य, नौगम्य.

Navigate, v. नावा तॄ 1 P or सृ 1 A or गम् 1 P or भ्रम् 1, 4 P. **2** (A ship) चल् c., वह् c., नी 1 P, प्रेर् c. -**ion,** s. नावा तरणं-भ्रमणं-पर्यटनं, नौयात्रा, नौभ्रमणं-गमनं, समुद्रयानं-यात्रा. **2** नौवाहनं-चालनं-नयनं. **3** नाविकविद्या, नौकागमनविद्या-शास्त्रं. -**or,** s. नाविकः, समुद्रयायिन् m. **2** नौवाहः, नौचालकः.

Navy, s. (युद्ध-) नौसमूहः-साधनं, पोतावलि f., नौकासमूहः.

Nay, adv. न, नहि; ' n. more ' नैवमेव, अन्यच्च, अन्यदपि, पुनः, न केवलं इदं; ' say n. ' **Deny,** q. v.

Neap, a. नीच, निम्न.

Near, prep. समीपं-पे (with gen.), आरात् (with abl.), समया, निकषा (with acc.), उप in comp.; (with verbs) ex. by उप, आ, अभि, प्रति. -a. आसन्न, प्रत्यासन्न, सन्निहित, समीप, निकट, समीप-निकट-स्थ, उपांत, अंतिक, समीप-निकट-वर्तिन्, उपकंठ संनिकृष्ट, सविध, अभ्यास-श, सदेश, सवेश, अभ्यर्ण, अभ्यग्र, सनीड, समर्याद, अदूर; ' quite n. ' संसक्त, अव्यवहित, अपदांतर; ' very n. ' नेदिष्ठ, अंतिकतम. **2** दृढसंबद्ध-संसक्त, परिचित. **3** स्वार्थसंबंधिन्. **4** कृपण, अल्पव्ययिन्; (relation) निकट, आसन्न; ' who is n. her delivery ' आसन्नप्रसवा; 'n. his death' आसन्नमृत्युः. -adv. समीपं-पे, अंतिकं-के, निकटं-टे, अभितः, उपांते, आरात्, निकषा, अदूरं-रे, संनिधौ, सकाशे, उप in comp.; ' n. at one 's side' पार्श्वे, पार्श्वतः. **2** Nearly, See below. -v. t. उप-गम् 1 P, उपसृ 1 P, समीपं-गम्; See **Approach. -ly,** adv. प्रायः, प्रायेण, प्रायशः, ईषदूनं, कल्प-प्राय-भूयिष्ठ-उप-in comp.; ' n. like Kumara ' कुमारकल्पः; ' n. dead ' मृतप्राय-कल्प; 'n. five years old ' पंचवर्षदेशीय; ' n. four ' उपचतुर. **2** दृढं, गाढं, ' n. connected ' दृढसंबद्ध. -**ness,** s. आसन्नता, नैकट्यं, संनिधिः, अभ्यासः, संनिकर्षः, सामीप्यं. **2** दृढसंसर्गः-संबंधः संसक्ति f., परिचयः. **3** कार्पण्यं, दैन्यं.

Neat, a. शुद्ध, शोभन, परिष्कृत, विनीत, परिमृष्ट, सुरेख. **2** कुशल, प्रवीण. **3** गोजातीय; ' n.- herd ' गोपालः. -**ly,** adv. विनीतं, शुद्धतया, शोभनप्रकारेण. -**ness,** s. शुद्धता, परिष्कारः, परिपाटि-टी f.

Nebula, s. शुक्रं, शुक्रपटलं.

Nebulous, a. मेघावृत, मेघाच्छन्न; See **Cloudy.**

Necessary, a. अवश्य, अवश्यंभाविन्, अपरिहार्य, अवश्यकरणीय, अवश्यक, आवश्यक (की f.), भवितव्य, भाव्य, अनिवार्य. **2** अपेक्षित, आकांक्षित. **3** विधि-दैव-वश, दैवाधीन; 'the n. result of acts ' कार्य-कर्म-वशः; oft. ex by pot. pass. part. or अर्ह् 1 P. -s. शौचकूपः. -ian, s. दैववादिन् m.; दैवपरः; See **Fatalist.** -**ies,** अवश्यवस्तूनि, द्रव्यसंभारः, उपकरणसामग्री; ' n. of life ' अन्नोदकं, अन्नाच्छादनं. -**ily,** adv. अवश्यं, नूनं, खलु, अवश्यं-नियतं-एव.

Necessity, s. अवश्यंभाविता, अनन्यगतित्वं, आवश्यकत्वं, अवश्यकता, नियतत्वं, अवश्यकर्तव्यता, कार्यवशः, **2** दैन्यं, दीनता, दुर्गति f., दारिद्र्यं, आपद्वशा. **3** प्रयोजनं,

हेतुः, कारणं, अर्थः, निमित्तं, कार्यं; अपेक्षा, आकांक्षा. 4 भवितव्यता, नियति *f.*, दैवं, विधिः, दैवाधीनता. **-ate,** *v. t.* अवश्यीकृ 8 U; also ex. by अवश्यं; 'your insolence n. s your dismissal' दुर्वृत्ततयावश्यं (स्वाधिकारात्) दूरीकर्तव्यः. 2 प्रसह्य अवश्यं कृ c.; *See* **Compel.** **-ous,** *a.* दुर्गत, दीन, दरिद्र.

Neck, *s.* ग्रीवा, गलः, कंठः, कंधरा-रः, शिरोधरा, शिरोधिः; 'back of the n.' अवटुः, घाटा, कृकाटिका; 'n. of a pitcher' पात्रकंठः; 'seize by the n. and turn out' अर्धचंद्रं दत्त्वा निःसृ c.; 'n.-cloth' 'n.-kerchief' ग्रीवावस्त्रं, गलावरणं, ग्रैवेयकं; 'n.-lace', हारः, माला, सूत्रं, ग्रैवं, ग्रैवेयकं, कंठमाला-भूषा-आभरणं; 'n.-lace of jewels' मणिमाला, रत्नावलि-ली *f.*; 'n.-lace of pearls' मुक्तावलिः, मुक्तालता, मौक्तिकसरः; 'n.-lace of gold' कनकसूत्रं.

Necrology, *s.* मृतजनवृत्तांतः.

Necromancy, *s.* प्रेतसिद्धि *f.*, पिशाचविद्या, भूतविद्या ... *See* **Magic, -ian.**

Nectar, *s.* अमृतं, सुधा, पी(पे)यूषं, सुधा-अमृत-रसः; 'n. of flowers' मधु *n.*, पुष्पासवः, पुष्परसः, मकरंदः, मरंदः. **-ean, -eous, -ine,** *a.* अमृतोपम, सुधातुल्य, अमृत-सुधा-मय (यी *f.*).

Need, *s.* प्रयोजनं, कार्यं, अर्थः, उपयोगः, or ex. by किं (with instr.) कारणं, निमित्तं, हेतुः, अपेक्षा, आकांक्षा; 'rich persons have n. of (even) a straw' तृणेन कार्यं भवतीश्वराणां (P. I. 1); 'according to n.' यथाप्रयोजनं, प्रयोजनवशात्. 2 व्यसनं, आपद् *f.*, कृच्छ्रं, कष्टं, दुर्गति *f.*, दुःखं, दारिद्र्यं, क्लेशः, संकटसमयः; 'times of n.' आपत्समयः; 'a friend in n. is a friend indeed' स सुहृद् व्यसने यः स्यात्. **-v. t.** अपेक्ष् 1 A, आकांक्ष् 1 P; प्रार्थ् 10 A, इष् 6 P; oft. ex. by (*s.*); 'he n. s help' तस्य साहाय्येन प्रयोजनं. 2 (Must) ex. by अवश्यं or by अर्ह् 1 P, or pot. pass. part.: 'you n. not come to me' मां प्रत्यागमनं न तेऽवश्यकं. **-ful,** *a.* अपेक्षित, अपेक्षणीय, आवश्यक आकांक्षित. **-less,** *a.* निरर्थक, निष्प्रयोजन, निरपेक्ष, निष्कारण, अहेतुक. **-lessly,** *adv.* निरर्थकं, निष्प्रयोजनं, व्यर्थं, हेतुं विना. **-lessness,** *s.* अकारणं, कारणाभावः. **-y,** *a.* दरिद्र, दीन, निःस्व, अकिंचन, दुर्गत; *See* **Poor.** **-Needs,** *adv.* अवश्यं (एव), नूनं, खलु.

Needle, *s.* सूचि-ची *f.*, सेवनी; 'the eye of a n.' सूचिरंध्र-छिद्रं; 'a magnetic n.' लोहमणिसूचिका; 'n.-maker' सूचिकारः; 'n.-woman' सूचिका; 'n.-work' सूचिकर्मन् *n.*, सूत्रकर्मन् *n.*

Nefarious, *a.* अतिघोर, अतिदुष्ट, नीच, क्रूरकर्मन्, दुष्टतम, पापिष्ठ, महा-अति-पातकिन्. **-ly,** *adv.* अतिघोरं, अतिदुष्टतया. **-ness,** *s.* अतिघोरता, पापिष्ठता.

Negative, *a.* अस्वीकारार्थक, निषेधार्थक, नास्तिधर्म, निषेधद्योतिन्, अभावरूप, अकरणरूप, अभावात्मक; 'n. quantity' ऋणराशिः. **-s.** नञ्, निषेधार्थक-अस्वीकारार्थक-शब्दः. 2 नास्ति-अभाव-पक्षः, निषेधवाक्यं 'two n.s make one affirmative' द्वौ नञौ प्रकृतार्थं गमयतः; 'to reply in the n.' नेति वद् 1 P. **-v. t.** नि-प्रति-षिध् 1 P, प्रत्यादिश् 6 P, प्रत्या-ख्या 2 P, निरस् 4 U, अपलप् 1 P; *See* **Confute, Reject.** **-ly,** *adv.* नेति, नास्तीति, सनिषेधं, अस्वीकारेण. **-Negation,** *s.* प्रत्याख्यानं, प्रत्यादेशः, निषेधः, अस्वीकारः, अपलापः. 2 अभावः.

Neglect, *v. t.* उपेक्ष् 1 A, न अनुष्ठा 1 P or आचर् 1 P, वि-स्मृ 1 P, प्र-मद् 4 P (with abl.), न अव-धा 3 U or श्रु 5 P (words); प्रमादतः त्यज् 1 P; 'n. ed his duty' स्वाधिकारात्प्रमत्तः (Me. 1). 2 अतिचर्, अतिवृत् 1 A, अति-व्यति-क्रम् 1 U, 4 P, उद्-लंघ् 1 A, 10; त्यज्, हा 3 P, अपास् 4 U. 3 अव-ज्ञा 9 U, अव-मन् 4 A, अवगण् 10, अव-धीर् 10, तिरस्कृ 8 U, न गण् or आदृ 6 A; *See* **Contemn.** **-s. Negligence,** *s.* उपेक्षा, अनवे(पे)क्षा, प्रमादः, अनवधानं, विस्मरणं, असावधानत्वं 2 त्यागः, अननुष्ठानं, लोपः, अति-व्यति-क्रमः, अतिपातः, लंघनं, उपात्ययः, उत्सर्जनं. 3 अवज्ञा, अवमानः, अनादरः, अवधीरणं-णा. **-ful, -Negligent,** *a.* उपेक्षक, मंदादर, निरपेक्ष, अनवधान, प्रमत्त, अनवहित, असावधान, प्रमादिन्. **-fully,** *adv.* सोपेक्षं, निरपेक्षं, उपेक्षया, मंदादरं, अनवहितं, असावधानं, प्रमादतः, प्रमादेन, सप्रमादं, प्रमत्तवत्, असमीक्ष्य.

Negotiate, *v. i.* व्यवहृ 1 P, पण् 1 A. 2 संधये संवद् 1 P. **-v. t.** संधि-धा 3 U, व्यवहारेण सं-धा. 2 वि-क्री 9 A. **-ion,** *s.* पणनं, व्यवहारः. 2 संधिक्रमः, सामन् *n.*, क्षमणं, मध्यस्थाश्रयः. **-or,** *s.* व्यवहारिन् *m.*, पणिकः, व्यवहर्तृ *m.* 2 मध्यस्थः, संधि-साम-विद् *m.*, सामकुशलः.

Negro, *s.* श्यामदेहः, कृष्णांगः.

Neigh, *v. i.* हेष्-ह्रेष्-रेष् 1 A. **-s., -ing,** *s.* हे(ह्रे)षा, हेषारवः, हेषितं, अश्वनादः-स्वनः.

Neighbour, *s.* प्रतिवेशिन् *m.*, प्रतिवेशः-श्यः, प्रतिवासिन् *m.*, प्रातिवेशिकः, निकट or समीप-

स्थः-वर्तिन् *m*. वासिन् *m*., सामंतः; 'next door n.' प्रातिवेश्यः, अनंतरवासी. -*a* प्रतिवासिन्, समीपस्थ, &c. -*v. t.* निकटे स्था 1 P or वृत् 1 A or वस् 1 P; *See* **Border.** **-hood,** *s*. संनिधिः, उपकंठः, सांनिध्यं, सामीप्यं, संनिकर्षः, उपांतः-तं, नैकट्यं, अभ्यासः. 2 समीप-संनिहित-देशः, सामंत, प्रतिवेशः, अधिवासः. 3 समीप-निकट-वासिनः, प्रातिवेश्याः, प्रतिवासिनः, (pl.). **-ing,** *a*. समीप-निकट-वर्तिन्, समीप-निकट-स्थ, सामंत, संनिहित, उपांत, आसन्न; *See* **Near.** **-ly,** *a*. प्रतिवासयोग्य; उपकारशील, हित.

Neither, (nor) *a., conj*. न-न वा, न च न च, (न च न परिच्छिन्नो न चाप्यगम्यः M. 1), or simply न-न, (मा-मा, with Imperative). 2 एक, एकतर, अन्यतर with न, or by उभौ.

Neogamist, *s*. नवोढः-ढा, नवभार्या, नवपतिः.

Neology, *s*. नूतनन्यायः-मतं. 2 नूतनशब्दाश्रयः. **-ist,** *s*. नूतनमताश्रयिन् *m*., नूतनन्यायसेविन् *m*.

Neophyte, *s*. नवशिष्यः-छात्रः, अनभ्यस्तः, प्राथमकल्पिकः, अपरिचितः.

Nepenthe, *s*. दुःखशमनं.

Nephew, *s*. भ्रात्रीयः, भ्रातृव्यः-जः, भ्रातृपुत्रः-सुतः. 2 (Sister's son) भागिनेयः, स्वस्रीयः, भगिनी or स्वसृ-पुत्रः or सुतः.

Nephritic,-al, *a*. वृक्कसंबंधिन् 2 वृक्करोगहर.

Nepotism, *s*. ज्ञात्यतिस्नेहः, कुलपक्षपातः.

Nereid, *s*. जल-समुद्र-देवता.

Nerve, *s*. शिरा, वस्नसा, स्नसा; धमनि-नी *f*., मज्जा-ज्ञान-तंतुः. 2 बलं, वीर्यं, तेजस्-ओजस् *n*., शरीरदृढता. 3 धैर्यं, धृति *f*., मनःस्थैर्यं -*v. t*. बलं-धैर्यं दा 3 U or वृध् *c*. **-less,** *a*. निर्बल, दुर्बल, शक्तिहीन. **-ous,** *a*. शिराल; मज्जातंतुगत. 2 ओजस्विन्, सबल, वीर्यवत्, ऊर्जस्वल, सुदृढ, धीर. 3 क्षिप्रक्षोभ, कंप-वेपन-शील, धैर्यहीन. **-ously,** *adv*. सवीर्यं, सबलं. 2 सकंपं, धैर्यं विना. **-ousness,** *s*. वीर्यं, ओजस् *n*. ऊर्जस् *n*. बलं. 2 स्नायुविकारः, कंपशीलता, अधृतिः.

Nescience, *s*. *See* **Ignorance.**

Nest, *s*. नीडः-डं, कुलायः, निलयः, पक्षिस्थानं-गृहं. 2 गृहं, स्थानं, आधारः, आश्रयः; 'find a mare's n.' शशविषाणं आसद् *c*. or लभ् 1 A. **-Nestle,** *v. i*. (पक्षिवत्) नीडं आश्रि 1 U or अधि-शी 2 A, सुखेन शी or संविश् 6 P or नि-ली 4 A. -*v. t*. पुष् 1, 4, 9 P or c, पा c. (पालयति). **-ing,** *s*. नीडस्थः पक्षिशावः.

Net, *s*. जालं, पाशः, बंधनं-नी, पाशबंधः, वि-(वी)तंसः; 'n. for deer' वागुरा, मृगबंधनी, मृगजालं; 'n. for fish' आनायः, जालं; 'n.-work' जाल-सूत्र-कर्मन् *n*. 2 कूटयंत्रं, उन्मायः. -*a*. शुद्ध, अशेष, निष्क्षार, अभग्न, अखंड, अन्यून. -*v. t*. जाले बंध् 9 P or ग्रह् 9 U. 2 जालीकृ 8 U.

Nether, *a*. अधस् in comp.; अधर, अवर, अधःस्थ, अधोभव, अधस्तन (नी *f*.); 'n. world' अधोलोकः; 'n. garment' अधोवासः. **-most,** *a*. अधरतम.

Nettle, *s*. पीतपर्णी. -*v. t*. सं-परि-तप् *c*., प्रकुप् *c*., क्रुध् *c*.; *See* **Enrage, Excite.**

Neural, *a*. वस्नसा-शिरा-संबंधिन् **-gia,** *s*. वातशूलं.

Neurology, *s*. शिरावर्णनं.

Neurotomy, *s*. शिराच्छेदविद्या.

Neuter, *a*. नपुंसक, क्लीब, तृतीय(या)-प्रकृति, षंढ; 'n. gender' क्लीबं, नपुंसकं; *See* below. **-Neutral,** *a*. मध्यस्थ, तटस्थ, उदासीन, अपक्षपातिन्, समदृष्टि, समभाव, उभयसामान्य, अपक्षपात; *See* **Indifferent.** -*s*. तटस्थः, उभयसामान्यः. **-ity,** *s*. माध्यस्थ्यं ताटस्थ्यं, अपक्षपातः, औदासीन्यं, उभयसाम्यं, समभावः, समदृष्टि *f*. **-ly,** *adv*. औदासीन्येन, उभयसामान्यं, समभावेन. **-Neutralize,** *v. t*. विशिष्ट-गुणान् नश् *c*., दुर्बलीकृ 8 U, बलं-शक्तिं-नश् *c*. 2 उदासीनीकृ. **-ation,** *s*. विशिष्टगुणनाशः-शनं, विशेषधर्मलोपः, दुर्बलीकरणं. 2 उदासीनीकरणं. **-ed,** *a*. नष्ट-गुण-शक्ति-बल.

Never, *adv*. न कदाचित्, न कदापि, न कदाचन, न जातु, न कर्हिचित्; 'n.-fading' अजर; 'n.-failing' अमोघ, अव्यय; 'n. more' न भूयः, नेतःपरं, न पुनः.

Nevertheless, *conj*. तथापि, किंतु, पुनः, परंतु, परं.

New, *a*. नव, नवीन, अभिनव, नूतन, प्रत्यग्र (of flowers &c.). 2 आधुनिक (की *f*.), इदानींतन-अधुनातन-(नी *f*.), अर्वाचीन. 3 अपूर्व अभूत-अदृष्ट-पूर्व, अश्रुतपूर्व. 4 अनभ्यस्त, अपरिचित, अविज्ञानिन्; 'n. comer' आगंतुकः, नवागतः; 'n.-born' नवोत्पन्न, सद्योजात; 'n.-fangled' 'n. fashioned' नवघटित, नवकल्पित-सृष्ट; 'n. year's day' वर्षप्रतिपद् *f*. **-ly,** *adv*. नवं, प्रत्यग्रं, सद्यः, नूतनं, नव in comp.; 'n. married wife' नवोढा, नवपाणिग्रहणा वधूः; 'n. ripe (blown)' प्रत्यग्रविकासित. **-ness,** *s*. नवीनता, अपूर्वता. 2 नूतनारीतिः, नवाचारः.

News, *s*. वार्ता, वृत्तांतः, प्रवृत्ति *f*., उदंतः, समाचारः, वृत्तं. 2 संवादः, जनवादः-श्रुति *f*., लोकप्रवादः, किंवदंती; 'good n.' भद्रं, शुभं, शुभवार्ता; 'ill n.' अशुभं, अशुभवार्ता; 'ill n. travels fast' अशुभवार्ता सत्वरं बहुलीभवति; 'n.-monger' वार्तावृत्तिः, वार्तायनः, वार्तावहनवृत्तिः, 'n. paper' वार्ता-समाचार-पत्रं, वृत्तपत्रं.

Newt, *s*. क्षुद्रगोधा.

Next, *a*. (Of time) आगामिन्; 'on Monday n.' आगामिनि सोमवासरे. 2

अनंतर, अव्यवहित, अव्यवधान, संसक्त, निरंतराल; 'n. to the skin' शरीरसंसक्त. 3 सन्निहित, पार्श्वस्थ, अंतिक, समीप or निकटस्थ or वर्तिन्; *See* **Near**; oft. ex. by पर, अन्य, अंतरं in comp.; 'n. born' अनंतरज; 'in the absence of the fi st, the n. and so on' पूर्वाभावे परः परः; 'on the n. day' पराह्णे, परेद्युः; 'the n. world' परलोकः, लोकांतरं; 'n. door to' अदूर, ईषदून (with abl.); कल्प in comp.; 'in the n. world' अमुत्र, परत्र; 'n. moment' क्षणांतरं; 'n. but one' एकांतरं. -*adv.* अनंतरं, परं, परतः (with abl); ततः, तदनंतरं, अथ, परस्तात्, ततः-परं-ऊर्ध्वं; 'what n.' ततः किं, ततस्ततः.

Nexus, *s.* बंधः, संधिः.

Nib, *s.* चंचु *f.*, तुंडं. 2 अग्रं, आणि *f.*, अग्रभागः. **-bed,** *a.* साग्र, अणिमत्.

Nibble, *v. t.* (अल्पाल्पं) दंश् 1 P, अवकृत् 6 P, चर्व् 1 P, 10; क्रमशः-अल्पाल्पशः-खाद् 1 P or कृत् or भक्ष् 10. 2 छिद्रं अन्विष् 4 P, दोषं ग्रह् 9 U, असूयति (D.) (with dat.).

Nice, *a.* ललित, शोभन, सु in comp., सुभग, रम्य, रमणीय, रुचिर, मनोहर, साधु. 2 स्वादु, सुरस, मिष्ट, आस्वादवत्, रुचिर, रुचिकर. 3 सूक्ष्मबुद्धि-दर्शिन्, कुशाग्रबुद्धि. 4 सूक्ष्म, अतिसूक्ष्म, सुपरिशुद्ध, सम्यञ्च्. 5 अस्थूल, सूक्ष्म, विरल (cloth). 6 कोमल, मृदु, पेलव, सुकुमार. 7 अतिसूक्ष्म, अतिनिपुण. **-ly,** *adv.* सुष्ठु, सु pr., ललितं, शोभनं, सम्यक्. 2 सूक्ष्मं, सूक्ष्मत्वेन. **-ness,-ty,** *s.* लालित्यं, रम्यता, स्वादुता, सौरस्यं; सूक्ष्मदृष्टि *f.*, सूक्ष्मदर्शिता, कुशाग्रमतित्वं, सूक्ष्मता; युक्ति *f.*, नीति *f.*

Niche, *s.* (प्रतिमा-) आधारः, निकेतनं, स्थानं.

Nick, *s.* ग्रंथिः; अवच्छेदः. 2 शुभ-अनुकूल-समयः, युक्त-उचित-कालः, शुभयोगः-कालः-लग्नं. -*v. t.* अवच्छिद् 7 P. 2 शुभलग्ने आसद् c.

Nickname, *s.* संज्ञा, उपाधिः, उपाधिनामन् *n.* -*v. t.* उपाधिं दा 3 U.

Nictate, *v. i.* निमिष् 6 P; नि-मील् 1 P. **-ion,** *s.* निमेषः; निमीलनं.

Nidification, *s.* नीडकरणं, कुलायरचनं.

Niece, *s.* भ्रातृकन्या-सुता, भ्रात्रीया. 2 (Sister's daught r) भागिनेयी, स्वस्रीया.

Niggard, *s.* कृपणः, क्षुद्रः, कदर्यः. -*a.*, **-ly,** *a.* कृपण, क्षुद्र, कदर्य, त्यागविमुख (खी *f.*), बद्धमुष्टि. **-ly,** *adv.* कृपणवत्, अल्पव्ययेन. **-ness,** *s.* कार्पण्यं, कदर्यता; *See* **Miser,** &c.

Niggle, *v. i.* कालापव्ययं. कृ 8 U.

Nigh, *a.*, *adv.* *See* **Near.**

Night, *s.* रात्रि-त्री, रजनिः-नी, क्षपा, निशा, विभावरी, श(शा)र्वरी, यामिनी, त्रियामा, निशीथिनी, क्षणदा, तमस्विनी, तमिः-स्री-स्रा, (all *f.*): 'a dark n.' तमिस्रा, तामसी; 'moon'ight n.' ज्यौत्स्नी, ज्योतिष्मती; 'by n.', 'at n.' रात्रौ, निशि, नक्तं, दोषा; 'number of n. s' गणरात्रं; 'beginning of n.' प्रदोषः, रजनीमुखं, निशामुखं; 'n. and day' रात्रिंदिवं, नक्तंदिवं; 'a n. and 2days' पक्षिणी; 'sitting up at n.' रात्रिजागरः; 'n.-attack' सौप्तिकं, सौप्तिकाक्रमः; 'n.-blindness' रात्र्यंधता; 'n.-dress' रात्रिवेशः; 'n.-fall' प्रदोषः, निशा-रजनी-मुखं, संध्याकालः, रात्रियोगः; 'n.-hag' रात्रिचरा, रात्र्यटा; 'n.-man' खल-मल-पूः; 'n. mare' दुःस्वप्नः, कुस्वप्नः; 'n.-shade' निदिग्धिका, स्पृक्की, व्याघ्री, बृहती, कंटकारिका, प्रचोदनी, कुली, क्षुद्रा, दुःस्पर्शा, राष्ट्रिका; 'n-wanderin' निशाचर, रात्रि(त्रिं)चर; 'n.-watch' नगररक्षिणः (pl.); यामः, प्रहरः. **-ly,** *a.* नैश (शी *f.*), दोषातन (नी *f.*), (*s.*) in comp.; 'n. watch' रात्रिजागरणं. -*adv.* रात्रौ, निशि, नक्तं. 2 प्रतिरात्रं, निशिनिशि, रात्रौ रात्रौ.

Nightingale, *s.* प्रियगीतः, बुलबुलः.

Nihil, *s.* शून्यं, अभावः. **-ism,** *s.* शून्यवादः. **ist,** *s.* शून्यवादिन् *m.* **-ity,** *s.* अभावः, शून्यता.

Nimble, *a.* चपल, लघु, लघुगति, लघुशरीर, चपलदेह, क्षिप्र-चपल-गति; 'n.-footed' लघुपाद्; 'n.-handed' लघुहस्त; 'n.-witted' चपल-शीघ्र-बुद्धि. **-ness,** *s.* लघुता, देहचापल्यं, चापल्यं, क्षिप्रता. **-Nimbly,** *adv.* लघु, लघु-द्रुत-गत्या, चपलतया, द्रुतं.

Nine, *a.*, *s.* नवन्; 'n.-fold' नवगुण. **-Ninth,** *a.* नवम (मी *f.*); 'n. ly' 'in the n. place' नवमस्थाने. **-Nineteen,** *a.*, *s.* नवदशन्, ऊनविंशति *f.*; 'n.-th' नवदश (शी *f.*). **-Ninety,** *a.*, *s*, नवति *f.*

Ninny, *s.* अल्पधीः, मूर्खः, जडः.

Nip, *v. t.* नि-,कृत् 6 P, अवछिद् 7 P 2 संदंश् 1 P, चर्व् 1 P, 10. 3 पीड् 10, अर्द् 1 P or c. 4 नश् c., उच्छिद्, विष्लु 6 P or c.; म्लानीकृ 8 U; 'n. in the bud' कलिकावस्थायां एव नश् c., जातमात्रं हन् 2 P or प्रशमं नी 1 P, (जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् P. III. 1). -*s.*, **-ping,** *s.* निकृंतनं, अवच्छेदः. 2 हिमार्तीकरणं. **-ped,** *a.* छिन्न, पीडित, &c. 3 हिमार्त, हिमपीडित. **-Nippers,** *s.* संदंशः-शकः, कंकमुखं.

Nipple, *s.* चूचुकः-कं. स्तन-कुच-अग्रं, स्तनमुखं.

Nit, *s.* लिक्षा, यूकांडं. **-ty,** *a.* लिक्षापूर्ण.

Nitre, *s.* यवक्षारः, यवाग्रजः, पाक्यः. **-ous,-y,** *a.* यवक्षारमय (यी *f.*).

Nitrogen, *s.* निर्जुष्यधातु *m.*

No, *adv.* न, नो, नहि; 'n , n.' मा मैवं. *-a.* (Before nouns) ex. by न; अ, अन्, निर् pr.; हीन, शून्य, रहित in comp., 'n. one' न कोपि, न कश्चन; 'n.-body' न कश्चित्, न काचन; 'having n. issue' अनपत्य, वंशहीन, &c.

Noble, *a.* कुलीन, अभिजात, आर्य, अभिजनवत्,महाकुल, सत्कुलजात, महंशज, कुल-ज or जात, कुलप्रसूत, वंशविशुद्ध 2 (N.-minded) उदार, महात्मन्, महामनस्, उदात्त,उदार-धी-मति, महानुभाव, महाशय, महेच्छ. 3 महत्, धीर, श्रेष्ठ, उत्कृष्ट, विशिष्ट, उत्तम, महाभाग, उन्नत, प्रमुख, प्रशस्त, वि-प्र-ख्यात, प्रतिपत्तिमत्, सुप्रतिष्ठ, कीर्तिमत्, यशस्विन्; श्रीमत्, महाप्रताप, महातेजस्, तेजस्विन्, ओजस्विन्; *See* **Majestic** also; oft. ex. by ऋषभः, सिंहः,व्याघ्रः, पुंगवः, शार्दूलः in comp.; *See,* **Excellent;** 'n.-looking' धीरदर्शन; महानुभावाकृति; 'n. in reason' उदात्तधी 'n. animal' उदात्तसत्त्वं; 'n. nature' सत्त्वं. *-s.,* 'N.-man' शिष्टजनः, कुलीनः, कुलीन-उत्कृष्ट-पदस्थः, आर्यजनः, अभिजनवत् *m.* **-ness,** *s.* महत्त्वं, महिमन् *m.*, उत्कर्षः, उन्नति *f.*, श्रेष्ठता &c.; प्रतापः, वैभवं; *See* below. **-Nobly,** *adv.* कुलीनवत्, आभिजात्येन; 'n. born' कुलोत्पन्न; *See* (*a.*). 2 औदार्येण, उदारतया, माहात्म्येन, उदारचेतसा, उदात्तं, धीरं. 3 सप्रतापं, अतितेजसा, महाविभूत्या, ऐश्वर्येण. **-Nobility,** *s.* कुलीनता, आर्यता, आभिजात्यं, कुलोत्कर्षः, सद्वंशता. 2 औदार्यं, माहात्म्यं, महानुभावः, उदारधीः; महाशयः, महिमन् *m.* 3 महत्त्वं, महिमा, उत्कर्षः, विशिष्टता, श्रेष्ठत्वं, प्रकर्षः, उन्नतिः, प्रतिपत्ति *f.*, प्रतिष्ठा, प्र-वि-ख्याति *f.* 4 प्रतापः, ऐश्वर्यं, विभूति *f.*, ओजस्-तेजस् *n.*, धीरता, श्रीः. 5 शिष्ट-कुलीन-जनः, कुलीनलोकाः-जनाः. **-Noblesse,** *s.* कुलीनजनाः, कुलीनजनसमाजः.

Nocent, *a.* *See* **Mischievous.**

Noctivagant, *a.* रात्रिचर.

Nocturnal, *a.* *See* **Nightly.**

Nod, *s.* शिरःकंपः-चालनं, शिरःसंज्ञा-संकेतः. 2 शिरः-मस्तक-प्रणामः. *-v.* (मस्तकं, शिरः) चल् c.; 'Mâlati n. s her head' मालती मूर्धानं चालयति (Mal. 8); शिरसा संकेतं-संज्ञां कृ 8 U or दा 3 U; 'n. consent' शिरःकंपेन अनुमन् 4 A or अनुमतिं सूच् 10. 2 (शिरः) प्र-आ-वि-अव-नम् c. (नमयति).

Nodated, *a.* ग्रंथिल, ग्रंथिमत्.

Noddle, *s.* *See* **Head.**

Noddy, *s.* *See* **Idiot.**

Node, *s.* घातः. 2 अस्थिगुल्मः, गंडः, पिंडः.

Nodose, *a.* ग्रंथिल, ग्रंथिमत्.

Nodule, *s.* घनः, पिंडः; शर्करा, लोष्टः.

Noise, *s.* नि-,नादः, ध्वनिः, शब्दः, नि-,स्वनः, घोषः, महा-उच्च-स्वरः, उत्क्रोशः, वि-,रावः, रवः, निर्ह्रादः; 'rattling n.' रणितं, रणत्कारः; 'jingling n.' क्वणः, क्वणनं, क्वणितं; 'loud n.' कलकलः, कोलाहलः, तुमुलं, महाशब्दः-स्वनः-घोषः. 2 जनरवः-प्रवादः-श्रुति *f.*: 'make n.' नद् 1 P, ध्वन् 1 P, वि-,रु 2 P, रण् 1 P, शब्दायते (D.), कोलाहलं-कलकलं-कृ 8 U; 'shallow water makes great n.' अर्धो घटो घोषमुपैति नूनं. *-v. t.* घुष् 10, उत्-वि-°, प्रकाश् c., प्र-, ख्या c (ख्यापयति), प्रकटीकृ. **-ful,** *a.* सशब्द; *See* Noisy below. **-less,** *a.* निःशब्द, नीरव, निर्घोष. **-lessly,** *adv.* निःशब्दं, नीरवं. **-Noisy,** *a.* महाशब्द-स्वन-नाद, तुमुल-महाशब्द-कोलाहल-कारिन्. मुखर, घोषण, घोषकारिन्, घोषकर (री *f.*). बहु-महा-घोष; बहु-कृत-कलकल. 2 निनादपूरित, कलकलव्याप्त, मुखर, सशब्द, नादिन्, सं-नि-न्नादिन्. **-ily,** *adv.* उच्चैः-स्वरेण, महाशब्देन. **-iness,** *s.* महाशब्दः-ध्वनिः.

Noisome, *a.* दुर्गंध, पूतिगंधि, कुत्सित, दुष्ट, समल. 2 मारक, मारात्मक, क्षयकर (री *f.*), नाशावह, घातुक, बाधक. **-ness,** *s.* दुर्गंधः, पूति *f.*, उग्रगंधता.

Nomad,-ic, *a.* पशुचारणोपजीविन्; अस्थिरवास.

Nome, *s.* प्र-,देशः, देशभागः.

Nomenclature, *s.* परिभाषा, पारिभाषिकशब्दसंग्रहः.

Nominal, *a.* नामसंबंधिन्, नामविषयक. 2 शाब्द (ब्दी *f.*), शाब्दिक-वाचनिक-(की *f.*). 3 नाममात्र, नामधारिन्-भृत्, नाममात्रधारिन्, शब्द-नाम-in comp.; 'I am but a n. lord of the earth' ननु शब्दपतिः क्षितेरहं (R. viii. 52); 'n. verb' नामधातुः. **-ly,** *adv.* शब्द-नाम-मात्रेण, नामत एव, शब्दतः.

Nominate, *v. t.* नाम-संज्ञां-कृ 8 U, नाम निर्दिश् 6 P; *See* **Call, Name.** 2 (To an office) नियुज् 7 A, 10 or प्रति-स्था c. (-ष्ठापयति). **-ion,** *s.* नियोगः, नियोजनं, प्रतिष्ठापनं. **-ive,** *s.* कर्तृ *m.*, कर्तृवाचकः,प्रथमा विभक्तिः. **-or,** *s.* नियोजकः. **-Nominee,** *s.* नियुक्तः, अधिकृतः.

Non, (a prefix) Ex. by अ, अन्; 'n.-acceptance' अपरिग्रहः, अस्वीकारः; 'n.-appearance,n.-attendance' अनुपस्थिति *f.* असंनिधानं, अदर्शनं, अविद्यमानता; 'n.-attainment' अप्राप्ति *f.*, अलाभः; 'n. attention' अनवधानं, प्रमादः; 'n.-chalant' निरुत्सुक, अनपे(पे)क्ष, उदासीन, निःस्पृह;

'n.-compliance' अननुरोधः, अननुवर्तनं, विरोधः; 'n.-conductor' अवाहकः, अवा-पकः; 'n.-conformist' अननुरोधिन् m., अननुवर्तिन्, सामान्यधर्मविरोधिन् m. मतांतर-ग्राहिन् m. 'n.-conformity' अननुरोधः, मतांतरग्रहणं; 'n.-descript' अवर्णित, अकृतल-क्षण; 'n. resistance' अप्रतीकारः; &c. &c.

Nonage, *s.* बाल्यं, बाल्यदशा; *See* **Minority.**

Nonagenarian, *s.* नवतिवर्षीयः.

Nonagon, *s.* नवकोणाकृति *f.*

Nonce, *s.* अवसरः, कालः; 'for the n.' अस्मिन्समये.

Nonchalance, *s.* औदासीन्यं, अनपेक्षा.

Nondescript, *a.* विचित्र, अपरूप, विलक्षण

None, *a.* न कश्चित्, न कोपि, न कश्चन, न काचित्, &c.; oft. ex. by न with other words; 'n. other' नान्य, नेतर; 'n. but' एव; with compar. adj.) न किमपि, न ईषदपि, न मनागपि, न स्तोकमपि.

Nonentity, *s.* अभावः, असंभवः, असत्ता, असद्भावः, शून्यता. 2 शून्यं, अवस्तु *n.*; 'he is a n. in the kingdom' राज्ये अकिंचि-त्करः सः.

None-such, *s.* निरुपमं or अद्वितीयं वस्तु *n.*

Nonfeasance, *s.* अकर्मन् *n.*

Nonpareil, *a.* अप्रतिम, अनुपम, अद्वितीय.

Nonplus, *v. t.* कुंठ् 10, वि-,मुह् *c.*, व्याकु-लीकृ 8 U, निरुत्तरीकृ. —*s.* कुंठता, वि-,मोहः, निरुत्तरता, अमति *f.*, निरुपायता. —**ed,** *a.* कुंठित, निरुपाय, मतिहीन, अप्रतिभ, मूढ, निरुत्तर.

Nonsense, *s.* असंबद्ध-अनर्थक-वाक्यं-वचनं-भाषणं, वृथाकथा-आलापः, प्रलापः, अल्पितं, असत्यं, अयाथार्थ्यं, अनर्थकं; 'to talk n.' प्रलप् 1 P, प्रजल्प् 1 P, असंबद्धं भाष् 1 A; 'talking n.' असंबद्धप्रलापिन्, वाचाल, जल्पक. —**Nonsensical,** *a.* असं-बद्ध, असंगत, अनर्थक, निरर्थक, वृथार्थक, अयथार्थ. —**ly,** *adv.* अनर्थकं, असंबद्धं, असं-गतं, मुधा, वृथा. —**ness,** *s.* असंबद्धता, &c.

Nonsuited, *a.* वाद-हीन-वाद्, अपसृत,: अ-र्थाद् हीन; 'to be n.' अपसृ 1 P, अर्थाद्-वादाद् हा pass.

Noodle, *s.* मूढः, मूर्खः, अल्पधीः, जडमतिः.

Nook, *s.* कोणः, अस्रः; विविक्तस्थानं.

Noon, *s.* (N.-time) मध्याह्नः, मध्यदिनं, मध्याह्नकालः. —*a.* माध्याह्निक (की *f.*), माध्यंदिन (नी *f.*).

Noose, *s.* पाशः, वागुरा, बंधनं; *See* **Snare;** 'n. for the neck' कंठपाशः. —*v. t.* पाशेन बंध् 9 P, पाशे बद्ध् 9 U or बंध् *c.*

Nor, *conj.* न च, न वा; *See* **Neither.**

Norm, *s.* आदर्शः, निदर्शनं. 2 विधिः, नियमः, सूत्रं. —**al,** *a.* यथाक्रम, वैधिक (की *f.*). 2 नियमानुसारिन्.

North, *s.* उत्तरा, उदीची, उत्तरदिश्-दिशा, उत्तराशा, कौबेरी; 'to the n.' उत्तरे (with abl.), उत्तरतः (with gen.); 'facing the n.' उदङ्मुख-*a.* (खी *f.*).

—*a.*, **-erly,-ern,** *a.* उत्तर, उदीचीन, उत्तर-स्थ, उदीच्य, उदच्; 'in a n. direction' उत्तरेण (with acc. or gen.); 'n.-east' उत्तरपूर्वा, पूर्वोत्तरा, ऐशानी, प्रागुत्तरा, प्रागु-दीची; (*a.*,-erly,-ern), प्रागुत्तर, पूर्वोत्तर, प्रागुदीचीन; पूर्वोत्तरस्थ; 'n.-pole' 'n.-star' ध्रुवः; 'n.-west' उत्तरपश्चिमा, वायवी; (*a.*,-erly,-ern) वायव, वायुदिक्स्थ. —**ward,** *a.* उत्तर, उत्तरदिक्स्थ. —**wards,** *adv.* उत्तराभिमुखं, उत्तरतः, उत्तरेण, उत्तर-दिशि.

Nose, *s.* नासा, नासिका, घ्राणं, घोणा, नसा, नस्या, गंधवहा, गंधज्ञा; 'led by the n.' नस्योत, नस्तित; (fig.) यथेच्छं कृष्ट, स्वे-च्छया नीत; 'aquiline n.' शुकनासा; 'having a sharp n.' खरणस्, खरणस; 'having a hoof-like n.' खुरणस्, खुर-णस; 'having a flat n.' नतनासिक; *See* under **Flat;** 'having a prominent n.' प्रलंबघोण, घोणोन्नत; 'breathing through the n.' नासिकंधम; 'n.-string' नस्यं; 'n.-cut' छिन्ननास; 'n.-gay' कुसुमस्तबकः, पुष्पगुच्छः, गुच्छः, गुत्सः; 'n.-ring' नासा-भरणं. —**less,** *a.* अ-वि-नासिक, विग्र, विख, विख्य, गतनासिक. —**Nostril,** *s.* नासारंध्र-विवरं-छिद्रं-पुटं-बिलं.

Nosology, *s.* रोगनिदानशास्त्रं.

Nostrum, *s.* गुप्तौषधं.

Not, *adv.* न, नो, न हि. 2 (Prohibitive) मा; oft. by अलं with instr. or gerund; 'do n. fear' अलं भयेन, मा भैषीः; 'do n. boast much' अलमलं बहु विकत्थ्य (M. 1); 'do n. do so', 'do n. say so' मा मा एवं; (rather angrily) मा तावत्. 3 (Privative) अ, निर्, अन्, वि pr.

Notch, *s.* छेदः, दंतः, भंगः; 'n. of a bow' अटनि-नी *f.* —*v. t.* अव-,छिद् 7 P, दंतुरी-भंगुरी-कृ 8 U. —**ed,** *a.* दंतुर, भंगुर, दंतुरित.

Note, *s.* लिंगं, लक्षणं, चिह्नं, अंकः; अभिज्ञानं. 2 स्मरणचिह्नं, स्मरणं. 3 टीका, व्याख्या, भाष्यं, टिप्पणी, वृत्ति *f.*; 'edited with n. s' टिप्पणीसमेतं प्रकाशितं (पुस्तकं). 4 स्वरः, ध्वनिः; 'a wrong n.' अप-वि-स्वरः; 'high n.' तारः, तारस्वरः; 'cracked n.' काकस्वरः; 'key-n.' वादिन् *m.*; (the seven n. s being निषादः, ऋषभः, गांधारः, षड्जः, मध्यमः, धैवतः, पंचमः); 'sweet n.' काकली; 'sweet indistinct n.' कलः; 'deep n.' मंद्रः; 'continued n.' तान-वासः. 5 ख्याति *f.*, कीर्ति *f.*, यशस् *n.*, प्रतिष्ठा. 'of n.' विश्रुत, ख्यातकीर्ति-प्रतिष्ठ. 6

वि-,रुतं, रावः, नादः, स्वनः, शब्दः, ध्वनिः. 7 अवेक्षा, अवधानं, मनोयोगः, अभिनिवेशः; 'take n. of' अवेक्ष् 1 A, अव-धा 3 U, मनसि-चित्ते-कृ 8 U, अवधृ 10. 8 पत्रं, पत्रकं, लेखः, लेख्यं; 'n.-book' स्मरण-अंकन-पुस्तकं; 'n.-worthy' स्मरणीय, स्मरणार्ह, अवेक्षणीय. —*v. t.* निर्वर्ण् 10, आलक्ष् 10, निरूप् 10, अवेक्ष्, आलोच् 10, आलोक् 1A, 10. 2 लिख् 6 P, (लेख्ये) आरुह् *c.* (रोपयति), (पत्रे) निविश् *c.* 3 अंक् 10, चिह्नयति (D.). **-able,** *a.* स्मरणीय, स्मरणार्ह, स्मर्तव्य. 2 विशिष्ट, उत्कृष्ट, परम; ख्यात, प्रसिद्ध, विशेष in comp.; 'a n. guest' अतिथिविशेषः. —*s.* कुलीन-विशिष्ट-जनः, आर्यः; *See* **Noble.** **-ably,** *adv.* प्रसिद्धं, विशेषेण, विशेषतः. **-ary,** *s.* लेखकः, लिपिकारः, लिपिजीविन् *m.* **-ation,** अंकनं, अंकविद्या. **-ed,** *a.* लक्षित, निरूपित, लिखित, पत्रारूढ. 2 प्र-वि-ख्यात, सुविश्रुत, प्रसिद्ध, लब्धप्रतिष्ठ, प्रथित.

Nothing, *s.* अभावः, शून्यं, असत् *n.*, अवस्तु *n.*, असत्त्वं. 2 न किंचित्, न किमपि, न स्तोकमपि. 3 अल्प-लघु-विषयः, अल्पार्थः, अनुवर्थः; 'for n.' अकारणं, अनिमित्तं, वृथा, मुधा, निरर्थकं; 'good for n.' व्यर्थ, निरर्थक, अकिंचित्कर (री *f.*). 'n. but' नान्यत् किमपि (with abl.). —*adv.* न मनागपि, न किंचिदपि, न स्तोकमपि, न मनाक्, न किमपि. **-ness,** *s.* अभावः, शून्यता.

Notice, *v. t.* लक्ष् 10, सं-आ-°, निरूप् 10, आलोक् 1 A, 10, प्र-अव-निर्-परि-ईक्ष् 1 A, दृश् 1 P, निर्वर्ण् 10. 2 मनो धा 3 U, अव-धा 3 U, सावधान —*a.* भू 1 P. 3 अभि-धा, निर्दिश् 6 P, उद्दिश्, कथ् 10, वर्ण्. 4 संभू *c.*, आदृ 6 A, संमन् *c.*, सत्कृ 8 U. —*s.* आलोकनं, निरूपणं, अवेक्षा-क्षणं, परीक्षा-क्षणं. 2 निर्देशः, उल्लेखः, अभिधानं, उद्देशः, कथनं, वर्णनं. 3 अवेक्षा, मनोयोगः, अवधानं, चित्ताभिनिवेशः, विचारः, गणना; 'take n. of' आदृ, अवेक्ष्, विचर् *c.*, आलोच् 10; *See* **Consider.** 4 सूचना, निवेदनं, बोधनं, बोधः. 5 विज्ञापना, विज्ञप्ति *f.*, घोषणं-णा, ख्यापना; 'written n.' घोषण-विज्ञप्ति-प्रसिद्धि-पत्रं. 6 आदरः, सत्कारः, संभावना, संमानः.

Notify, *v. t.* वि-,ज्ञा *c.* (ज्ञापयति), बुध् *c.*, प्रकाश् *c.*, सूच् 10, घुष् 10, प्र-ख्या *c.*, (ख्यापयति), नि-आ-विद् *c.*, कृत् 10. **-ication,** *s.* विज्ञापनं-ना, विज्ञप्ति *f.*, घोषणा, सूचनं-ना, ख्यापनं.

Notion, *s.* मति *f.*, बुद्धि *f.*, बोधः, मनोगतं, मतं, कल्पना, भावः, अभिप्रायः, भावना, आशयः, वासना; 'under the n. that' इति बुद्ध्या. **-al,** *a.* मनः-कृत, मनोगत, मनःकल्पित, संकल्पज, *See* **Ideal.**

Notorious, *a.* प्रसिद्ध, प्र-वि-ख्यात, प्रथित, विश्रुत, विज्ञात, लोकप्रसिद्ध-विश्रुत, लौकिक (की *f.*); 'a n. report' सार्वलौकिकःप्रवादः. 2 दुर्नामन्, कुख्यातिमत्, ख्यातगर्हण, कुप्रसिद्ध, 'a n. thief' सर्वविज्ञातः चौरः; 'to become n.' बहुलीभू 1 P, प्रकटीभू, सर्वप्रकाशतां गम् 1 P. **-ly,** *adv.* सुप्रसिद्धं, प्रकटं, ख्यातगर्हणं. **-ness,-Notoriety,** *s.* प्र-वि-ख्याति *f.*, प्रकाशता, प्रसिद्धि *f.*, विश्रुति *f.*, प्रथा. 2 दुर्नामन् *n.*, कुकीर्ति *f.*, वाच्यता, अपकीर्तिः.

Notwithstanding, *part.* तथापि, यद्यपि, एवं सत्यपि; gen. ex. by gen. or loc. abs. or by अनादृत्य (with acc.); 'n. his teacher's presence' पितमाकेपि गुरौ, *See* 'In spite of' under **Spite.**

Nought, *s.* *See* **Naught.**

Noun, *s.* नामन् *n.*, विशेष्यं, सुप्, वाचकः.

Nourish, *v. t.* पुष्-, पुष् 1, 4, 9 P or *c.*, संवृध् *c.*, परि-,पा *c.* (पालयति), सं-,भृ 1, 3 U; (अन्नादिना) आप्यै *c.*, बृंह् *c.*, तृप् *c.*, संतुप् *c.* **-er,** *s.* पालयितृ *m.*, संवर्धकः. **-ing,** *a.* पुष्टिकर (री *f.*), पुष्टिद, पौष्टिक (की *f.*). **-ment,** *s.* पोषणं, पुष्टि *f.*, पालनं, संवर्धनं, भरणं, अन्नदानं. 2 आहारः, भोजनं, भक्ष्यं, अन्नं, पौष्टिकं, जीवनसाधनं.

Novel, *a.* नव, नूतन, नवीन, अपूर्व, अदृष्ट-अश्रुत-पूर्व, अद्भुत; *See* **New.** —*s.* कल्पित-कथा, आख्यायिका, प्रबंधकल्पना, कृतार्थ-कथा. **-ist,** *s.* आख्यायिकाकारः. **-ty,** *s.* अपूर्वता, नवता, नूतनता. 2 अदृष्टपूर्वं वस्तु, कौतुकं, अद्भुतं.

November, *s.* कार्तिकमार्गशीर्षे.

Novennial, *a.* नववर्षीय.

Novercal, *a.* वैमात्रेय, वैमातृक (की *f.*), विमातृयोग्य.

Novice, *s.* शैक्षः, प्राथमकल्पिकः, नवशिष्यः-छात्रः, अनभ्यस्तः, अलब्धकौशलः. **-Novitiate,** *s.* नवशिष्यता, अनभ्यासः, नवच्छात्रदशा. 2 नवाभ्यासकालः, विद्यारंभावधिः.

Now, *adv.* अधुना, इदानीं, संप्रति, सांप्रतं, प्रस्तुत-वर्तमान-काले, इहसमये. 2 अथ, अथातः, अतःपरं, अतः; 'n.-n.' क्वचित्-क्वचित्, कदाचित्-कदाचित्, अंतरा-अंतरा, (अंतरा पितृसंकथामंतरा मातृसंबंधमालापं कुर्वन् Ka. 118); 'n. and then' काले काले, कदाचित्, कदापि; 'till n.' अद्य यावत्; 'from n.' अद्यारभ्य, अद्य प्रभृति, अतःपरं; 'just n.' अधुनैव, अचिरात्, इदानीमेव; 'n.-a-days' एषु दिवसेषु, संप्रति, अधुनातनकाले; 'n.-a-days people' इदानींतना-आधुनिका-जनाः.

No-wise, *adv.* न सर्वथा, न कथमपि.
Noxious, *a.* हिंस्र, उपद्रविन्, हिंसक, क्रूर, हिंसालु, घातुक, अपकारिन्, हिंसात्मक, अहित-अनिष्ट-कारिन्; *See* **Harmful.**
Nozzle, *s.* नासाग्रं, प्रोथः, नक्रः; अग्रं, अग्रभागः.
Nubile, *a. See* **Marriageable.**
Nubilous, *a.* मेघावृत, अभ्राच्छन्न; *See* **Cloudy.**
Nucleus, *s.* बीजं, गर्भः; संचयास्पदं.
Nude, *a.* नग्न, विवस्त्र; *See* **Naked.** **-ation** *s.* विवस्त्रीकरणं. **-ity,** *s.* नग्नता.
Nudge, *v.* '. कूर्परेण चल् c.
Nugatory, *a.* व्यर्थ, मोघ, निरर्थक, निष्फल, विफल, निष्प्रभाव, अप्रमाण, अनिष्पन्न.
Nugget, *s.* पिंडः, घनः.
Nuisance, *s.* उत्पातः, कंटकः, (of persons); बाधा, पीडा, पीडा-क्लेश-हेतुः; ' public n. ' लोककंटकः; ' family n. ' कुलाधिः, गृहोत्पातः.
Null, *a.* मोघ, व्यर्थ, निष्फल, विफल, निर्बल, निष्प्रभाव, अनिष्पन्न, लुप्त, वृथा-मुधा in comp. **-ify,** *v. t.* मोघी-विफली- कृ 8 U, लुप् 6 P or c., खंड् 10. **-ity,** *s.* मोघता, व्यर्थता, वैफल्यं. **2** अभावः, शून्यता.
Nulla, *s.* प्रणाली.
Numb, *a.* जड, सुप्त, स्तब्ध, अस्पंद, अचेतन, चैतन्य-रहित, स्तब्धगति; ' n. with cold ' शीताकुल. **-*v. t.*** जडीकृ 8 U, जडयति (D.), चैतन्यं हृ 1 P or स्तंभ् 9 P or c. **-ness,** *s.* जाड्यं, स्तंभः, जडिमन् *m.*, स्वापः, त्वक्सुप्ति *f.*, चैतन्यनाशः-स्तंभः.
Number, *s.* संख्या, राशिः. **2** संख्या, गणना, परिमाणं. **3** गणः, समूहः, निवहः, संघः; *See* **Multitude;** oft. ex. by बहु, बहुल, प्रचुर, अनेक, or जनः in comp.; ' a n. of young women ' युवतिजनः, तरुणीगणः; ' in n. s ' संघशः, गणशः, बहुशः, अनेकशः; ' a whole n. ' अभिख्यं. **4** अंकः. **5** छंदस् *n.*, पद्यं, कविता. **6** वचनं; ' science of n. ' गणितं, व्यक्तगणितं, अंकविद्या; '100 in n. ' शतं, शतसंख्यक. **-*v. t.*** सं-परिसं-ख्या 2 P, गण् 10, संकल् 10 (कलयति). **2** अंक् 10, अंकं लिख् 6 P or स्था c. (स्थापयति); oft. ex. by संख्या in comp.; ' the enemy's force n. ed 500 ' पंचशतसंख्यं शत्रुसैन्यं. **-er,** *s.* गणकः, संख्याकृत् *m.* **-ing,** *s.* गणनं-ना, संख्यानं. **-less,** *a.* असंख्य, संख्यातीत, गणनातीत, अगण्य, असंख्यात.
Numbles, *s.* मृगांत्राणि.
Numeral, *s.* संख्या, अंकः **-*a.*** संख्यात्मक, संख्यावाचक-विषय, संख्या in comp. **-ly,** *adv.* यथासंख्यं.
Numerary, *a.* नियतसंख्यक.
Numeration, *s.* संख्यानं, गणना.
Numerator, *s.* अंशः, लवः.
Numerical, *a.* संख्या in comp.; ' n. superiority ' संख्याधिक्य-उत्कर्षः. **-ly,** *adv.* संख्यामपेक्ष्य-उद्दिश्य, यथासंख्यं.
Numerous, *a.* बहु, बहुसंख्य, बहुल, भूरि, अनेक, प्रचुर, नैक; *See* **Many.** **-ly,** *adv.* बहुशः, बाहुल्येन, अनेकशः.
Numismatics, *s.* मुद्राविद्या.
Numskull, *s. See* **Idiot, Fool.**
Nun, *s.* परिव्राजिका, तपस्विनी, मठवासिनी, ब्रह्मचारिणी, तपोनिष्ठा. **-nery,** *s.* विहारः, मठः.
Nuncio, *s.* धर्माध्यक्षदूतः.
Nuncupative, *a.* शाब्दिक, वाचिक, अलिखित.
Nuptial, *a.* वैवाहिक-औद्वाहिक (की *f.*), वैवाह (ही *f.*), विवाह-परिणय- in comp.; ' n. ceremony ' परिणयविधिः, विवाहक्रिया; ' n. gift ' यौतकं, औद्वाहिकं, पारिणाय्यं; ' n. s ' विवाहः, उद्वाहः. परिणयः, पाणिग्रहणं.
Nurse, *s.* धात्री, उपमातृ *f.*, मातृका, अंकपाली. **2** परिचारिका, उपचारिका, कन्यापालिका. **3** पालकः, पोषकः. **-*v. t.*** (रोगिणं) उपचर् 1 P, सेव् 1 A, परि-पा c. (पालयति; यत्नादुपचर्यतामसौ (S. 3) ' let her be carefully n. ed. ' **2** पा c. (पालयति), पुष् 1, 4, 9 P, वृध् c., लल् 10; *See* **Nourish.** **3** दुग्धं पा c. (पाययति), स्तन्यं दा 3 U or धे c. (धापयति). **-ery,** *s.* पालन-पोषण-स्थानं; बालगृहं-स्थानं; 'n. song' शिशुगीतं; ' n. man ' पुष्पाजीविन् *m.* **-ing,** *s.* उपचारः, सेवा. **2** पालनं, पोषणं, लालनं. **-ling,** *s.* स्तनंधयः, स्तनपः, बालः, शिशुः.
Nurture, *v. t.* विनी 1 P, शिक्ष् c., उपदिश् 6 P. **2** पा c. (पालयति), पुष् 1, 4, 9 P or c., वृध् c.,; *See* **Nourish.** **-*s.*** आहारः, भक्ष्यं. **2** शिक्षणं, विनयः, उपदेशः. **3** पोषणं, पालनं, वर्धनं.
Nut, *s.* फलं; बीजं, गर्भः (internal contents); ' cocoa-n. ' नारिकेलफलं; ' 'n. crackers ' संदंशः-शकः; 'n-meg' जाति(ती)फलं, पुटकं; 'n.-shell' बीजकवचः-पुटं. **-arian,** *s.* फल-आहारिन्-उपजीविन् *m.*
Nutant, *a.* प्रणतशिरस्. **-Nutation,** *s.* शिरःकंपः.
Nutrition, *s.* पोषणं, पालनं, पुष्टि *f.*, आप्यायनं.
Nutriment, *s.* आहारः, पुष्टिदं अन्नं.
Nutritious,-Nutritive, *a.* पुष्टिकर (री *f.*), पुष्टिद, पौष्टिक (की *f.*), पोषक, धातु-बल वर्धक (की *f.*).
Nux vomica, *s.* कुचला

Nuzzle, *v. i.* नासां अवनम् c. (नमयति).
Nymph, *s.* अप्सरस् *f.*, अप्सरा, स्वर्वेश्या; देवता in comp.; 'wood-n.' वनदेवता; 'sea-n.' जलदेवता.
Nymphomania, *s.* उत्कटा, सुरतेच्छा.

O.

O, Oh, *interj.* हे, भोः, अयि, अये, अरे; हा, अहह (sorrow). 2 अहो (joy and surprise), हंत, अहो, बत. 3 आः (anger &c.). 4 आ, आं; 'oh for' ex. by अपि नाम, 'oh for a lodge in a wilderness' अपि नाम विपिने निवासं लभेय; 'oh that' See **Would.**
Oaf, *s.* *See* **Fool.**
Oak, *s.* सिंदूरः.
Oakum, *s.* खंडितरज्जु *f.*
Oar, *s.* क्षे(क्षि)पणि-णी *f.*, नौ-नौका-दंडः. –*v. t.* क्षेपण्या चल् c. or वह् c.; *See* **Row.** **–Oarsman,** *s.* नौदंडधरः.
Oasis, *s.* (मरुमध्ये) शाड्वलस्थलं, रम्यस्थानं.
Oath, *s.* शपथः, अभिशापः, वचनं, प्रतिज्ञा, समयः; 'bind by an o.' शप् c.; 'to take an o.' शप् 1, 4 U, शपथं शप्; 'with an o.' सशपथं, शपथपूर्वं.
Obdurate, *a.* अनम्र, कठिन, कठिनहृदय-चित्त, अनुतापविमुख (खी *f.*), दुराग्रह; *See* **Hard.** **–Obduracy,** *s.* चित्तकाठिन्यं, कठोरहृदयता, अनुतापविमुखता; काठिन्यं, कठोरता.
Obeisance, *s.* नमस्कारः; प्रणामः, प्रणति *f.*, वंदनं, प्रणिपातः, नमस्या; अभिवादनं; 'prostrate o.' साष्टांगप्रणामः-नमस्कारः, अष्टांगपातः; 'to make an o.' प्रणम् 1 P, प्रणिपत् 1 P, नमस्कृ 8 U, अभिवद् c.
Obelisk, *s.* सूच्याकारः स्तंभः.
Obese, *a.* पीन, पीवर, स्थूल; *See* **Fat.**
Obey, *v. t.* (Orders) कृ 8 U, अनु-ष्ठा 1 P, अनुवृत् 1 A, अनुवि-धा 3 U, पा c. (पालयति), अनुरुध् 4 A, मन् c., प्रतिग्रह् 9 P, अभ्युप-इ 2 P or गम् 1 P; (persons) वचनं श्रु 5 P, शासने स्था, आज्ञां-वचनं-अनुवृत्, यथादिष्टं वि-धा; श्रु desid. (शुश्रूषते), उपचर् 1 P, सेव् 1 A, उपास् 2 A, आज्ञां कृ or अनुरुध् &c. **–Obedient,** *a.* आज्ञानुवर्तिन्, आज्ञाकर (री *f.*), आज्ञाविधायिन्, अनुविधायिन्, अनुरोधिन्, आज्ञा-निदेश-कारिन्. आज्ञापर, विधेय, विनयग्राहिन्, वचने स्थित, आश्रव, वश्य, प्रणेय, वशानुग, शुश्रूषु, आज्ञावचनग्राहिन्-सेविन्, आज्ञाधीन; 'o. to one's parents' पितृवश्य, पितृवचनपर. **–ly,** *adv.* आज्ञानुसारेण, यथाज्ञं, यथादिष्टं, निदेशानुरोधेन. **–Obedience,** *s.* आज्ञानुवर्तनं-अनुरोधः-अनुसारः-अनुसरणं-करणं-पालनं-सेवनं-धारणं, वश्यता, अनुविधायित्वं, शुश्रूषा, आज्ञाकरत्वं, आज्ञापरता, अनुवर्तनं, अनुरोधः.
Obit, *s.* *See* '**Death.**' **–uary,** *a.* मृत्युसंबंधिन्. –*s.* मृत्युलेखः.
Object, *s.* द्रव्यं, वस्तु *n.*, अर्थः, विषयः, इंद्रियार्थः; 'visible o.' चक्षुर्विषयः; (fig.) पात्रं, पदं, स्थानं, आस्पदं, भाजनं, भूमि *f.*, विषयः; 'o. of confidence' विश्वासास्पदं, विश्वासभूमिः; 'the sole o. of my affection' स्नेहस्यैकायनीभूता (M. 2). 'o. of dispute' विवादविषयः, व्यवहारास्पदं. 2 अर्थः, फलं, हेतुः; (desired o.) अभीष्टं, इष्टं, समीहितं, कांक्षितं, ईप्सितं, कामः, मनोरथः; *See* **Desire.** 3 निमित्तं, कारणं, प्रयोजनं, कार्यं. 4 अभिप्रायः, आशयः, तात्पर्यं, उद्देशः, लक्ष्यं; 'with what o. in view' किमपेक्ष्य फलं, केन हेतुना, किमुद्दिश्य, किंनिमित्तं, किमर्थं; 'accomplishment of one's o.' कृतार्थता, चरितार्थता, इष्टसिद्धि *f.*, फलप्राप्ति *f.*; 'highest o.' परमार्थः; 'o. of hearing' श्रुतिविषयः. 5 कर्मन् *n.*; 'a root governing two o.s' द्विकर्मकः धातुः. –*v.* वि-प्रति-रुध् 7 U, बाध् 1 A, खंड् 10, निरस् 4 U, अंगीकृ 8 U, अपवद् 1 A, न अनुमन् 4 A or अनुमुद् 1 A, दोषं ग्रह् 9 U, 'the sage will not o. to this' नात्र दोषं ग्रहीष्यति कुलपतिः (S. 3); नि-प्रति-षिध् 1 P, (तदेष सर्वः न भवद्भिः प्रतिषेधनीयः R. xiv. 42); in discussions gen. ex. by ननु, इति चेत् or कथं तर्हि, followed by उच्यते or अत्रोच्यते (we reply); प्रत्यव-स्था 1 A, वितंड् 1 A. **–ion,** *s.* बाधः-धा, अपवादः, विरोधः, आक्षेपः, दोषः, आपत्ति *f.*, कक्षा, उद्ग्राहः, विरुद्धहेतुः, विप्रतिषेधः, प्रत्यवायः, प्रतिबंधः, पर्युदासः, 'making an o.' दोषग्रहणं, विरोधोपन्यासः; 'settling an o.' समाप्रतिसमा-धानं, आक्षेपपरिहारः. **–ionable,** *a.* बाध्य, सबाध, सदोष, निषेधार्ह. वर्ज्य, परिहार्य, आशंकनीय. **–ive,** *a.* विषयाश्रित, पदार्थनिष्ठ, कर्मविषयक. **–or,** *s.* बाधकः, अपवादकः.
Objuration, *s.* शपथः.
Objurgate, *v. t.* निंद् 1 P, भर्त्स् 10 A. उपालभ् 1 A, आ-अधि-क्षिप् 6 P, तिरस्कृ 8 U. **–ion,** *s.* निंदा, भर्त्सनं-ना, उपालंभः, आक्षेपः, धिक्कारः; *See* **Censure.** **–ory,** *a.* निंदक, निंदात्मक.

Oblation, *s.* बलिः, उपहारः, उपायनं, हव्यं, हवनं, हुतं, आहुतिः *f.*, इष्टि *f.*, यागः, निवपणं; 'o. of eatables' नैवेद्यं; 'o. to all deities' वैश्वदेवः; 'to make o. s to fire' हु 3 P.

Obligate, *v. t. See* Oblige, below.

Oblige, *v. t.* Ex. by causal of verbs, gen. with बलेन or बलात्; प्रयुज् 10, प्रवृत् c.; *See* **Compel. 2** नियमपूर्वं-समयसिद्धं बंध् 9 P. **3** अनुग्रह् 9 P, उपकृ 8 U, उपकारेण बंध्, हितं-प्रसादं-उपकारं कृ; 'I am much o ed to you for this reward' एतेन पारितोषिकदानेन भवता सुतरामुपकृतोस्मि-अनुगृहीतोस्मि; 'I am much o. ed' अनुगृहीतोस्मि, महानयं प्रसादः. **-ation,** *s.* अवश्यकता, कर्तव्यता, भारः, ऋणं, बंधः, धर्मः; 'free from the o. s of debt' ऋणमुक्त, मुक्तर्ण, अनृण; religious o.' व्रतं, नियमः, चोदना, विधिः. **2** संविद् *f.*, समयः, प्रतिज्ञा, नियमः, अभ्युपगमः, संधा, सं-आ-श्रवः. **3** अनुग्रहः, उपकारः, उपकृति *f.*-तं, हितं; प्रियं; 'under o.' उपकृत-अनुगृहीत-*a.*; 'my o. s to you are immense' तव मयि उपकाराः संख्यातीताः; 'to lay under o. s' उपकृ; *See* (*v.*). **-atory,** *a.* अवश्यक आवश्यक (की *f.*), अपरिहार्य, अवश्यकर्तव्य; oft ex. by अवश्यं; *See* under **Compel.-ing** *a.* अनुग्रह-उपकार-शील, उपकारिन्, अनुग्राहिन्, हित-उपकार-कारिन्, सुशील, दाक्षिण्य, अनुकूल, सुजन. **-ingly,** *adv.* दाक्षिण्येन, सुजनतया, सानुग्रहं, सुशीलवत्. **-ingness,** *s.* उपकार-अनुग्रह-शीलं, सौजन्यं.

Oblique, *a.* वक्र, कुटिल, जिह्म, असरल, तिर्यच्, अर्जु(?), विषम; 'o. speech' वक्रोक्ति *f.*, भंगि-भी *f.*, उपरोधवचनं; 'o. case' अप्रधानकारकं. **-ly,** *adv.* वक्रं,कुटिलं, तिर्यक्, तिरः, साचि, जिह्मं. **-ness,** *s.* वक्रता, कौटिल्यं, अनर्जुता, वैषम्यं; 'o. of sight' वक्रदृष्टि *f.*, दृष्टिवक्रता; 'o. of conduct' विमार्ग-उत्पथ-गमनं, असदाचारः, सत्पथभ्रंशः-त्यागः.

Obliterate, *v. t.* वि-,लुप् 6 P or c., प्र-परि-अव-मृज् 2 P or c., व्यामृश् 6 P or c., विनश् c., उच्छिद् 7 P, उन्मूल् 10. **-ion,** *s.* लोपः, मार्जनं, व्यामर्शः, उच्छेदः.

Oblivion, *s.* अ-वि-स्मृति *f.*, अ-वि-स्मरणं; 'to bury into o.' विस्मृ 1 P. **2** दोषविस्मरणं. **-Oblivious,** *a.* स्मृतिहर (री *f.*), विस्मारक,विस्मृतिकर (री *f.*).**2** विस्मरणशील.

Oblong, *a.* दीर्घाकार, आयत, दीर्घचतुरस्र. **-s.** आयतः.

Obloquy, *s.* निंदा, परि(री)वादः, अपवादः; वाच्यता, भर्त्सना, गर्हा; *See* **Censure, Calumny.**

Obnoxious, *a.* वश, अधीन, आयत्त, योग्य, अर्ह, पात्रं, आस्पदं, विषयः in comp.; ex. by pot. pass. part.; *See* **Liable, Apt. 2** गर्हित, द्वेष्य, द्वेषणीय, गर्ह्य, अप्रिय, अप्रिय, निंद्य, अप्रीतिकर (री *f.*). **-ly,** *adv.* अप्रियं, गर्हातया. **-ness,** *s.* अधीनता, वश्यता, पात्रता. **2** द्वेष्यता, गर्ह्यता.

Obscene, *a.* अश्लील, ग्राम्य, अनवार, अवाच्य, गर्ह्य, कुत्सित, कुरूप, बीभत्स, अश्राव्य, विपात, व्रीडावह. **2** अशुभ, अभद्र, अमंगल, अलक्षण. **-ly,** *adv* अश्लीलं, अवाच्यं. **-ity, -ness,** *s.* अश्लीलता, अवाच्यता; 'o. of language' दुरुक्ति *f.*, दुर्वाक्यं.

Obscure, *a.* तमोवृत, सांधकार, निष्प्रभ, मलिन, धूमिमित्र, निस्तेजस्, तमस्विन. **2** अप्रसिद्ध, नातिविश्रुत, अविज्ञात, अल्पयशस्, अल्पकीर्ति, लघुप्रसिद्ध. **3** नि-,गूढ, दुर्बोध, क्लिष्ट, दुर्ज्ञेय, गहन, दुर्गम, विषम, अप्रकाश, अस्पष्ट, अस्फुट, गूढार्थ, अव्यक्त. **-*v. t.*** (तमसा) प्र-आ-च्छद् 10, आ-वृ 5 U, उप-रुध् 7 U, अंतरयति (D.), मलिनी-तिमिरी-कृ 8 U, मलिनयति-तिमिरयति- (D.), प्रभां-तेजः-हृ 1 P or क्षि 1, 5 P.;'o. with clouds' मेघैः आच्छद् or आवृ **2** गह-नीकृ, गूढीकृ; ex. by (*a.*). **3** (Fig.) प्रत्या-दिश् 6 P, प्रत्या-ख्या 2 P, प्रच्छद्; *See* **Eclipse.** 'o. er of S'ri' प्रत्यादेशः श्रियः (V. 1). **-ation,** *s.* मलिनीकरणं, कांति-प्रभा-हरणं. **2** तेजः or प्रभा-क्षयः or हानि *f.*, निष्प्रभता, सांधकारता. **-ed,** *a.* तमोवृत, नष्ट-क्षीण-मलिनक्षत-प्रभ-कांति-प्रकाश, मलिन, निस्तेजस्, हतज्योतिस्. **-ity, -ness,** *s.* निष्प्रभता,तेजः or कांति-क्षयः or हानिः, तमस् *n.*, तमिस्रं, अंधकारः. **2** गूढता, गहनता, अस्फुटता, दुर्बोधता. **3** अप्रसिद्धि-अविख्याति-*f.*, अल्पप्रतिष्ठा-कीर्ति *f.* **-ly,** *adv.* निष्प्रभं, सतिमिरं, सांधकारं. **2** गूढं, दुर्बोधं, अदुगमं, अस्पष्टं, अव्यक्तं.

Obsecrate, *v. t. See* **Entreat.**

Obsequies, *s.* उत्तरकार्य-क्रिया, अंत्यकृत्यं, प्रेत-कार्य-क्रिया; अंत्येष्टिक्रिया, और्ध्वदेहिकक्रिया, अंत्येष्टि *f.*, प्रेत-संस्कारः, पारलौकिकं. **-Obsequial,** *a.* और्ध्वदेहिक-और्ध्वदैहिक-(की *f.*), अंत्येष्टियोग्य; by (*s*) in comp.

Obsequious, *a.* छंदोनुवर्तिन्, अत्यनुवर्तिन्, अत्युनुरोधिन्, वशवर्तिन्, वशानुग, विनत, नम्र; *See* **Obedient. -ly,** *adv.* अत्यनुरोधात्, छंदोनुवर्तनेन. **-ness,** *s.* अत्यनुरोधः, अत्यनुवृत्ति *f.*, छंदोनुवर्तनं.

Observe, *v. t.* दृश् 1 P, ईक्ष् 1 A, वि-आ-अव-लोक् 1 A, 10, निरूप् 10, आ-,लक्ष् 10, निर्वर्ण् 10, आलोच् 10 (o. carefully); *See* **Look. 2** उपलभ् 1 A, वि-भू c., वि-ज्ञा 9 U, अवधृ 10. **3** अनु-,पा c. (पालयति), रक्ष् 1 P, आ-अव-लंब् 1 A, आ-श्रि 1 U, आचर्

1 P, अनु-ष्ठा 1 P, सेव् 1 A, निषेव्, वि-धा 3 U, कृ 8 U; 'o. silence' मौनमाचर्; 'o. a fast' उपवस् 1 P; (rules) अनुवृत् 1 A, अनुसृ 1 P, अनुरुध् 4 A. 4 अभि-धा 3 U, वच् 2 P, ब्रू 2 U, वाक्यं वद् 1 P or उच्चर् c. **-able,** *a.* दृश्य, प्रेक्षणीय, दृष्टिगोचर. **2** अनुष्ठेय, निषेव्य. **-ance,** *s.* पालनं, रक्षणं, आचरणं, सेवनं, आलंबनं, अनुसरणं, अनुवर्तनं, विधानं, अनुष्ठानं. **2** आचारः, व्यवहारः, रीति *f.*, चरितं, आचारकर्मन् *n.*; 'religious o.' व्रतं, नियमः, विधिः. **-ant,** *a.* निरीक्षक, दर्शिन्, अवलोकिन्, सापेक्ष, अवहित, सावधान. **2** पालक, निषेवक, अनुसारिन्, आश्रित, आस्थित; 'o. of benefits' कृतज्ञ, कृतवेदिन्. **-ation,** *s.* अवलोकनं, निरीक्षणं, अपेक्षणं, अवेक्षा, निरूपणं, आलोचनं. **2** वचनं, उक्ति *f.*, उदाहारः, वाक्यं; लेखः, लिखितं (in writing). **-atory,** *s.* वेधगृहं-शाला. **-er,** *s.* प्रेक्षकः, अवेक्षकः, निरूपकः.

Obsess, *v. t.* आ-विश् 6 P. **2** पीड् 10, दू 5 P, अर्द् 1 P.

Obsolete, *a.* लुप्तप्रयोग, लुप्त, अप्रचलित, अप्रचल, गतव्यवहार, व्यवहारातीत, अव्यवहार्य. **-ness,** *s.* लोपः, अप्रचारः, अव्यवहारः.

Obstacle, *s.* अंतरायः, प्रत्यूहः, व्याघातः, प्रतिबंधः, वि-प्रति-ष्टंभः, वारणं, विघ्नः, रोधः, उप-प्रति-अव-नि°-, विघातः, बाधः-धा, व्यवधानं, प्रत्यर्थिन्, *m.*, 'though an o. to his meditation' प्रत्यर्थिभूतामपि समाधेः (K. I. 59).

Obstetric, *a.* प्रसवसंबंधिन्. **-s.** (O. s) गर्भमोचनशास्त्रं, प्रसवकर्मन् *n.*

Obstinate, *a.* प्रतिनिविष्ट, अविनेय, अवश्य, अननुनेतव्य, निर्बंधवत्, निर्बंधशील, स्वैरिन्, दुर्दम, आग्रहिन्, दुराग्रह, प्रतीप, कठिन, दृढ. **2** दुःसाध्य, दुरुपचार. **-ly,** *adv.* निर्बंधेन, अतिदृढं, स्वैरं, साग्रहं, सनिर्बंधं, दुराग्रहेण. **-ness,** **-obstinacy,** *s.* निर्बंधः, आग्रहः स्वैरिता, दुराग्रहः, निर्बंधशीलं, दृढता, अवश्यता, प्रतिनिविष्टता, प्रतीपता.

Obstipation, *s.* स्तंभनं, अवरोधः.

Obstreperous, *a.* बहुघोषकारिन्, महास्वन, तारस्वर, तुमुल, अत्युच्च, अतिपरुष (of noise). **-ly,** *adv.* उच्चैःस्वरेण, सकोलाहलं, तुमुलरवेण.

Obstruct, *v. t.* रुध् 7 U, नि-वि-सं-प्रति-उप°, वि-प्रति-व्या-हन् 2 P, वृ c., or वार् 10, वि-, स्तंभ् 9 P, or c., प्र-सं-बाध् 1 A, विघ्नयति (D.), नि-प्रति-षिध् 1 P. **-er,** *s.* विघ्नकरः, प्रतिबंधकः-रोधकः. **-ion,** *s.* रोधनं, वारणं, प्रतिबंधनं. **2** विघ्नः, अंतरायः, प्रत्यूहः, प्रतिबंधः, व्याघातः; *See* **Obstacle.** **3** आ-, नाहः, अवरोधः, प्रतिबंधः. **-ionist,** *s.* विघ्नकारिन् *m.*, प्रतिबंधशीलः. **-ive,-Obstruent,** *a.* संप्रतिरोधिन्, बाधक, प्रतिबंधक, विघ्नकारिन्, विघ्नकर (री *f.*), विघातिन्, निवारक.

Obtain, *v. t.* आप् 5 P, लभ् 1 A, विद् 6 U, अश् 5 A, अधिगम् 1 P, अर्ज् 1 P or c., आ-समा-सद् c., आ-प्रति-पद् 4 A, संपद् c.; oft. by इ-या-2 P; *See* **Get.** **-v.i.** प्रचल्-र् 1 P, प्रवृत् 1 A, सं-स्था 1 A; *See* **Hold.** **-able,** *a.* प्राप्य, लभ्य, अधिगम्य; 'easily o.' सुलभ, सुसाध्य; 'hardly o.' दुष्प्राप, दुर्लभ, दुराप. **-er,** *s.* अर्जकः, प्रापकः. **-ing,** *a.* प्रचलित, प्रवृत्त, स्थापित, प्रसिद्ध. **-ment,** *s.* लाभः, प्राप्ति *f.*, अधिगमः, अर्जनं.

Obtest, *v. t.* *See* **Entreat.**

Obtrude, *v. i.* हठात्-आगंतुकतया-बलेन-प्रविश् 6 P or गम् 1 P or आक्रम 1 U, 4 P. **-v. t.** बलेन प्रविश् c. or प्र-सृ c. **2** अतिनिर्बंधेन ग्रह् c. or प्र-दा 3 U or उपंन्यस् 4 U. **-Obtrusion,** *s.* बलेन प्रवेशः, अनाहूतगमनं, स-गर्व आक्रमः, आगंतुकभावः. **-Obtrusive,** *a.* धृष्ट, आगंतुक (की *f.*), सप्रगल्भ, बलात् प्रवेशक. **-ly,** *adv.* बलेन, हठात्, प्रसभं, प्रसह्य.

Obtund, *v. t.* घनीकृ 8 U, जडीकृ, तेजः हृ 1 P. **-Obtuse,** *a.* जड, मंद, स्थूल, मूढ, मंद-जड-मति-बुद्धि-धी. **2** अतीक्ष्ण, अतीव्र, अप्रखर, धाराहीन, निर्धार, घन, स्थूल, निस्तेजस्, अनिशित; 'o. angle' बहिर्लंब:-विषमः-कोणः. **-ly,** *adv.* जाड्येन; जडवत्, अतीव्रं, घनं, स्थूलं. **-ness,** *s.* जाड्यं, मूढता, मंदता; स्थूलता, घनता, अतीक्ष्णता,

Obvert, *v. t.* अधोमुखीकृ 8 U; अभिमुखीकृ. **-Obverse,** *s.* मुखं, अग्रभागः.

Obviate, *v. t.* परिहृ 1 P, नि-,वृ c., निरस् 4 U, प्रतिकृ 8 U, प्रतिवि-धा 3 U, विहन् 2 P, निवृत् c., वि-प्रति-रुध् 7 U: *See* **Obstruct.**

Obvious, *a.* स्पष्ट, व्यक्त, स्फुट, परिस्फुट, सुस्पष्ट-व्यक्त, सुगम, सुप्रकाश, भिन्नार्थ, स्पष्टार्थ; 'o. to the sight' दृष्टिगोचर, प्रत्यक्ष, सुलक्ष्य. **-ly,** *adv.* स्पष्टं, व्यक्तं, स्फुटं, सुप्रकाशं, भिन्नार्थं. **-ness,** *s.* स्पष्टता, स्फुटता.

Occasion, *v. t.* उत्पद् c., जन् c. (जनयति), आवह् 1 P, उद्भू c., भू 1 P (with dat.). **-s.** अवसरः, समयः, कालः. अवकाशः, प्रस्तावः, प्रसंगः, प्रसरः, वेला, स्थानं; 'according to the o.' यथावसरं, यथाकालं, प्रसंगानुरूपं, प्रस्तावसदृशं. **2** प्रयोजनं, अपेक्षा, आकांक्षा, उपयोगः, कार्यं, कारणं. **3** वृत्तं, संगति *f.*, घटनं-ना. **4** निमित्तं, हेतुः, प्रयोजनं, कारणं, उपाधिः. **-al,** *a.* नैमित्तिक-प्रासंगिक- (की *f.*), प्रसंगागत, कार्योपात्त, निमित्तापन्न. **2** आगंतुक-आपतिक (की *f.*), अनियत, अनित्य, अनियत-

कारण, अशुकाल, विरल, काहाचित्क (की *f.*); better by 'o.-ly'. **-ally,** *adv.* कदाचित्, कदापि, कश्चित्, काले काले, अंतरा अंतरा, प्रसंगवशात्, यथासंभवं, कार्यवशात्, निमित्तेन, प्रसंगानुरूपं. **-ed,** *a.* उत्पादित, उत्पन्न, जनित, जात, उदित, उद्भूत; gen. ex. by ज, उद्भव, प्रभव, मूल, कारण, निमित्त, कर्तृ, हेतु in comp.; 'fever o. by fatigues' श्रमनिमित्तः ज्वरः &c.

Occident, *s.* पश्चिमा, प्रतीची, पश्चिमा दिक्. **-al,** *a.* पश्चिम, प्रतीच्य, पाश्चात्य, प्रतीचीन.

Occiput, *s.* मस्तक-शिरः-पृष्ठं.

Occult, *a.* नि-,गूढ, दुर्ज्ञेय, दुर्बोध, गहन, गुप्त, अज्ञात, गूढार्थ. **-ism, -ness,** *s.* गूढता, गहनता.

Occultation, *s.* आच्छादनं, ग्रासः.

Occupy, *v. t.* अधि-ष्ठा 1 P, अधि-वस् 1 P, अध्यास् 2 A, आश्रि 1 U, आविश् 6 P, आ-अध्या-क्रम् 1 U, 4 P (all with acc.); व्याप् 5 P, पूर् 10, व्यश् 5 A; वृत् 1 A (with loc.), पदं कृ 8 U or वि-धा 3 U, स्था; 'o. a throne' राज्यमारुह्-राजपदमधिरुह् 1 P; 'o. ing the honourable position of a housewife' श्लाघ्ये गृहिणीपदे स्थिता (S. 4). 2 (Possess) भुज् 7 A, भू 1 P, 10, धा. 3 प्र-नि-युज् 7 A, 10, व्या-पृ c., प्रवृत् c., व्यापृत-*a.* कृ; 'o. oneself' व्यापृ 6 A, व्यापृत-निरत-आसक्त-*a.* भू 1 P, प्रवृत् (with loc.); आत्मानं व्यापृ c. **-ancy,** *s.* भोगः, भुक्ति *f.*, आवेशः, आक्रमः, अधिकारः. **-ant,** *s.* भोक्तृ भोगिन्, अधिकारिन् all *m.* **-ation,** *s.* वृत्ति *f.*, आ-उप-जीविका, आजीवः, जीवनसाधनं-उपायः. 2 क्रिया, कृत्यं, प्रवृत्तिः, चरितं, चेष्टा. 3 नियोगः, अधिकारः, स्वकर्मन् *n.* धर्मः. 4 अधिवासः, आवेशनं, अधिष्ठानं, व्याप्ति *f.*, आक्रमणं, भोगः, भुक्तिः; 'daily o.' नित्यकृत्यं; 'to do the usual morning o. s.' उचितेषु प्रभातकरणीयेषु (S. 4). **-ed,** *a.* आविष्ट, आक्रांत, अध्युषित, अध्यासित, अधिष्ठित, व्याप्त, भुक्त, आश्रित. 2 व्यापृत, व्यापारिन्, व्यवसायिन्, प्रवृत्त, कर्म-निष्ठ-रत-उद्युक्त, क्रियावत्; gen. ex. by रत, निष्ठ, मग्न, व्यापृत, पर in comp., or by व्यापृ, प्रवृत्. **-er,** *s.* अधिष्ठातृ *m.* भोक्तृ *m.*

Occur, *v. i.* वृत् 1 A, विद् 4 A; जन् 4 A, उत्पद् 4 A, सं-भू 1 P. 2 उप-स्था 1 U, आगम् 1 P, उप-नम् 1 P; *See* **Befall.** 3 सं-,वृत्, समा-पद्, घट् 1 A, आ-नि-पत् 1 P, सं-भू; 'o. to the mind' मनसि उद्-भू 2 P, or भू or जन् or स्फुर् 6 P, or आविः-प्रादुः-भू; 'this did not o. to his mind' इति तस्य बुद्धौ न संजातं, इति तस्य हृदये नापतितं (Ka. 288); 'the following (thoughts) o. ed to my mind' आसीत्-समभूत्-मे मनसि; 'these two verses o. to our memory (mind)' स्मृत्युपस्थितौ इमौ द्वौ श्लोकौ (U. 6). **-rence,** *s.* घटना-नं, वृत्तं, वृत्तांतः, भूतं, व्यतिकरः; संभवः, संगति *f.*, उत्पत्ति *f.*, उपस्थिति *f.*, उपागमः; 'of usual o.' नित्यसंभूत; 'of rare o.' दुर्लभ, चिरोपनत. **-rent,** *s.* शत्रुः; *See* **Enemy.** 2 वृत्तं, वृत्तांतः.

Ocean, *s.* समुद्रः, सागरः, सिंधुः, उदन्वान्, अर्णवः, रत्नाकरः, अकूपारः, पारावारः; and comp. of धिः, निधिः, पतिः, राशिः with 'Water' q. v.; वारिराशिः, जलनिधिः, अब्धिः, अंबुधिः, वार्धिः, अपांपतिः, सरित्पतिः, तोयराशिः, अंबुराशिः, &c.; 'o.-bound' सागरांत, समुद्रवलय-रसन-मेखल; 'o. of misery' दुःख-सागरः, व्यसनार्णवः. **-a., -ic,** *a.* सामुद्र (द्री *f.*), समुद्रीय. (*s.*) in comp.

Ochre, *s.* सुवर्णगैरिकं.

Ochlocracy, *s.* प्राकृतजनप्रभुत्वं.

Octagon, *s.* अष्टास्रं, अष्टकोणाकृति *f.* **-al, -Octangular,** *a.* अष्टकोण, अष्टास्र.

Octave, *s.* अष्टकं. **-Octavo,** *a.* अष्टपत्रक.

Octennial, *a.* अष्टवार्षिक (की *f.*), अष्टवर्षीय. 2 अष्टवर्षस्थायिन्.

October, आश्विनकार्तिकं.

Octogenarian, *a.* अशीतिवयस्क.

Octohedron, *s.* अष्टपृष्ठः.

Octopetalous, *a.* अष्टदल.

Octosyllable, *s.* अष्टाक्षरं.

Octuple, *a.* अष्टगुण, अष्टविध.

Ocular, *a.* चाक्षुष (षी *f.*), प्रत्यक्ष; 'o. evidence' प्रत्यक्ष-चाक्षुष-प्रमाणं, चाक्षुषज्ञानं. **-ly,** *adv.* प्रत्यक्षप्रमाणेन. **-Oculist,** *s.* चक्षुः-नेत्र-वैद्यः.

Odd, *a.* विषम, असम, अयुग्म. 2 विलक्षण, असाधारण (णी *f.*), अपरूप, असंगत, अपूर्व, वि-, चित्र, अद्भुत, असामान्य, लोकोत्तर; 'game of o. and even' मुष्टिद्यूतं. **-ity, -ness,** *s.* वैषम्यं. 2 वैलक्षण्यं, वैचित्र्यं, असंगति *f.*, अपूर्वता, आचारवैलक्षण्यं. 3 कौतुकं. **-ly,** *adv.* विषमं, चित्रं, विलक्षणं. **-Odds,** *s.* वैषम्यं, न्यूनाधिकभावः, तारतम्यं. 2 आधिक्यं, उत्कर्षः, विशेषः, श्रेष्ठता, विशिष्टता; 'fight at o.' आधिकबलेन शत्रुणा युध् 4 A.

Ode, *s.* गीतं, गानं, गेयं.

Odious, *a.* गर्हित, कुत्सित, निंद्य गर्ह्य, द्वेष्य, अप्रिय, द्वेषपात्रं-भाजनं-आस्पदं; कश्मल (report). 2 द्वेषावह, द्वेषोत्पादिन्. **-ly** *adv.* कुत्सितं, गर्हणीयतया. **-ness,** *s.* गर्ह्यता, द्वेष्यता. **-Odium,** *s.* वि-,द्वेषः, गर्हा, कुत्सनं, घृणा.

Odontalgy(ia), *s.* दंत-शूलं-पीडा-व्यथा.

Odour, *s.* गंधः, वासः; 'strong or fragrant o.' सुगंधः, सुवासः, सौरभं-भ्यं, आ-,मोदः, परिमलः; 'bad o.' दुर्गंधः, पूतिगंधः. **-ous, -Odoriferous**, *a.* सगंध, सुगंधि, परिमलवत्, सामोद, गंधवत्, सुरभि, सवास.

Œsophagus, *s.* *See* 'Gullet.'

Of, *prep.* Gen. ex. by genitive or by comp.; 'o. great strength' महाबल. 2 (Showing reference) अधिकृत्य, उद्दिश्य (with acc.), or by गत in comp.; 'by thinking o. her husband' भर्तृगततया चिंतया. 3 (Made of) by Tat. comp.: or मय (यी *f.*), निर्मित in comp.; or by derivatives; 'pot o. gold' हेमपात्रं, हेममयं or हैमं पात्रं. 4 (Partitive sense) by gen. or loc., or मध्ये, मध्यात् with gen. 5 (Apposition) ex. by comp. or by नाम *ind.*; 'the island o. Ceylon' सिंहलद्वीपं, सिंहलं नाम द्वीपं. 6 (Showing cause) by instr. or abl.; 'died o. fever' ज्वरेण मृतः.

Off, *adv.* दूरे, दूरं, दूरतः; (with verbs) ex. by अप, वि, निः, अव, उत्; 'o. with his head' उच्छेद्यतामस्य शिरः; 'o. with him to the prison' अपनीयतामसौ कारागृहं. *-a.*, 'far o.' दूरवर्तिन्, दूरस्थित-स्थ. *-interj.*, 'get o.', 'be o.' दूरं अपेहि, अपसर; 'o.-hand' प्रत्युत्पन्न, अचिंतितपूर्व, आकस्मिक (की *f.*), असावधान, निरपेक्ष; 'badly o.' दुःस्थित, दुर्गत, आपन्न, कृच्छ्रगत; 'well o.' सुस्थ, सुस्थित, संपन्न.

Offal, *s.* उच्छिष्टं, भुक्तावशेषः-षं, शेषान्नं, मलं, उच्छिष्टान्नं; मांसोच्छिष्टं, अवशिष्टमांसं.

Offend, *v.* अपराध् 4, 5 P (with gen. or loc.), विप्रियं-अनार्यं कृ 8 U or आचर् 1 P, अप्रसादं उत्पद् c.; कस्मिन्नपि पूजार्हे अपराद्धा शकुंतला (S. 4) 'Sakuntala has o.ed (committed an offence against) some respectable person'. 2 पीड् 10, व्यथ् c. (व्यथयति), क्लिश् 9 P, दु 5 P, सं-परि-तप् c. 3 (Against) अतिचर्, अति-व्यति-क्रम् 1 U, 4 P, लंघ् 1 A, 10, अतिवृत् 1 A, भिद् 7 P, भंज् 7 P, लुप् c. 4 रुष् c., कुप् c., प्र-,कुप् c., क्षुभ् c., कुपित-क्षुब्ध- *a.* कृ, कोपं जन् c. (जनयति); अप-अप-मन् c. 5 रुध् 7 U, बाध् 1 A, स्खल् c. (स्खलयति). **-ed** *a.* कुपित, क्षुब्ध, प्रकोपित, क्रुद्ध, रुष्ट, जात-मन्यु, संतप्त, असंतुष्ट. 2 बाधित, व्याहत, अभिभूत; 'to be o.' कुप्-क्रुध्-रुष् 4 P. **-er**, *s.* अपराधिन्, अपराद्धः, दोषिन्, पापिन्, पातकिन्, कृतागस्, कृतापराधः, सदोषः, अपराधकृत्, कुकर्मन् all *m.* **-Offence**, *s.* अपराधः, दोषः, पापं, पातकं, अघं, एनस्-आगस् *n.*, दुरितं, कुकर्मन् *n.* दुष्कृति *f.* 2 कोपः, क्रोधः, रोषः, अमर्षः, मन्युः, असंतोषः; 'easily taking o.' शीघ्रकोपिन्, सुलभकोप. 3 विप्रियं, अपमानः, अवज्ञा. 4 रोधः, बाधा-धः, स्खलनं; *See* **Obstacle.** **-less**, *a.* निर्दोष, निरपराध. **-Offensive**, *a.* कोपजनक (नी *f.*), रोषावह, अप्रिय, असुप्रीति-अप्रीति-कर (री *f.*), असुखद, अरम्य, विरुद्ध, कटु, असभ्य; 'o. to the ear' श्रवणकटु, कुश्राव्य; 'o. to the taste' विरस. 2 बीभत्स, जुगुप्सावह, गर्ह्य, कुत्सित, गर्हित, दुर् pr.; 'o. smell' दुर्गंधः, पूतिगंधः. 3 पीडाकर (री *f.*), अनिष्टावह, अहित, अपकारक, उपघातिन्; 'act on the o.' अपराधे अग्रेसरः भू 1 P: 'o. weapon' घातोपयुक्तं शस्त्रं. 4 आक्रामक, आ-अभिघातिन्. **-ly**, *adv.* सापकारं, अप्रियं, सापराधं, सदोषं. **-ness**, *s.* अप्रियता, कटुता, गर्ह्यता, सापकारता, घातुकता.

Offer, *v. t.* उप-नी 1 P, उप-हृ 1 P, प्र-उप-कॢप् c., उप-स्था c. (स्थापयति); प्र-दा 3 U, 1 P, प्रति-पद् c., निविद् c., ऋ c. (अर्पयति), निक्षिप् 6 P, सृज् c., उपहारं दा, उपढौकृ c. 2 उपन्यस् 4 U, उप-क्षिप्, पुरो नि-धा 3 U, अभि-धा, निर्-उद्-दिश् 6 P. 3 प्र-,दृश् c., प्रकटीकृ; प्रथ् c., प्रक्षिप्. 4 दा desid. (दित्सति-ते). 5 (As an oblation) उपहृ, निवप् 1 U, निर्वप्, उत्सृज् 6 P, ऋ c., उपहारीकृ, उपायनीकृ; 'o. mango-sprouts in memory of Smara' स्मरमुद्दिश्य निवपेः सहकारमंजरीः (K. IV. 38); 'water o.ed to the Manes' निवापसलिलं; 'o. a burnt oblation' हु 3 P; 'o. a price' मूल्यं निर्दिश् or अभि-धा; 'o. violence' बलात्कारं कृ. *-v. i.* उपस्था 1 U, आविः-प्रादुः-भू 1 P, उपनम् 1 P, दृश्-लक्ष् pass., आ-नि-पत् 1 P. 2 (Show willingness) ex. by desid. form, or वद् 1 P with future; 'he o.-ed to aid me' तव साहाय्यं करिष्यामीति उवाद. 3 प्रयत् 1 A, उद्यम् 1 A, चेष्ट् 1 A, उत्-सह् 1 A; *See* **Attempt**. *-s.* उपन्यासः, उपक्षेपः, प्रस्तावः, अभिधानं, निर्देशः, वचनं, निवेदनं, sometimes प्रार्थना; 'o. for marriage' विवाहप्रार्थना, 'makes an o. of' दित्सति. 2 प्रयत्नः, उद्यमः, प्रवृत्ति *f.* **-er**, *s.* उपहर्तृ, उपनेतृ, अर्पकः, निवेदकः, दातृ all *m.* **-ing**, *s.* उपहरणं, उपनयनं, अर्पणं. 2 बलिप्रदानं, बलिकर्मन् *n.* निर्वपणं, हवनं. 3 उपायनं, उपहारः, उत्सर्गः, बलिः, हव्यं, *See* **Oblation, Manes.** 4 (Sacrificial) हविस् *n.*, हव्यं, हुतं, आहुति *f.* 5 अर्घः, उपायनं, प्राभृतं.

Office, *s.* कर्मन् *n.*, कार्यं, नियोगः, क्रिया, कृत्यं, व्यापारः, धर्मः, प्र-,वृत्ति *f.* 2 अधिकारः, पदं, पदवी, स्थानं, आस्पदं, नियोगः, अधिकारपदं. 3 विधिसंग्रहः. 4 उद्योगस्थानं, कार्यालयगृहं, कार्यस्थानं; 'good o.' उपकारः, उपकृतं-ति *f.*, सुकृतं, अनुग्रहः, हितं; 'ill o.' अपकारः, अपक्रिया, अनिष्टं; 'holding o.', 'in o.' प्राप्ताधिकार, अधिकारस्थ, पदारूढ, अधिकृत; 'dismissed from o.' च्युत-भ्रष्ट-अधिकार, पदभ्रष्ट-च्युत; 'permanent o.' स्थिराधिकारः; 'temporary o.' चलपदं. **-Officer,** *s.* अधिकृतः, नियुक्तः, नियोगिन् *m.* अधिकारिन् *m.* आधिकारिकः, कार्याधिकः; 'o. of the king' राजपुरुषः-भृत्यः, प्रकृतिपुरुषः; 'o. of justice' धर्माधिकारिन् *m.* न्यायाध्यक्षः; 'military o.' सेनापदभाज् *m.* सैनिकाध्यक्षः; बलाधिपः. **-Official,** *a.* राजपुरुषः-भृत्यः, अधिकारी, नियोगी, पुरुषः, भृत्यः. *-a.* आधिकारिक (की *f.*), अधिकारपद-विषयकसंबंधिन्; अधिकारयुक्त. **-dom,** *s.* अधिकृतवर्गः. **-ly,** *adv.* अधिकारपूर्वं, अधिकारवशात्. **-Officious,** *a.* अनधिकारचर्चाशील, परकार्यचर्चक; *See* **Meddlesome.** 2 उपकारशील, अनुकूल, हित. 3 अत्युपचार, अत्युपकारिन्. **-ly,** *adv.* अधिकारचर्चया, सप्रश्रयं, प्रगल्भतया. **-ness,** *s.* अन्याधिकारचर्चा, परकार्यचर्चा-प्रवेशः.

Off-scouring, *s. See* **Dirt.**

Off-set, *s.* प्ररोहः, अंकुरः. *-v. t.* समिकृ 8 U.

Off-shoot, *s.* प्ररोहः. अंकुरः शाखा (lit. and fig.)

Offspring, *s.* संतानः, संतति *f.*, प्रसूति *f.* प्रजा, अपत्यं, प्रसवः, तोकं; 'male o.' पुत्रः, सूनुः, पुमपत्यं, पुंसंतानः; 'female o.' कन्या, सुता, स्त्र्यपत्यं; 'having no o.' निर्वंश, निरपत्य, निःसंतान.

Offuscate, *v. t. See* **Obscure.**

Oft, Often, (O.-times), *adv.* असकृत्, बहुशः-धा, बहु-अनेक-वारं, मुहुर्मुहुः, भूयो भूयः, अनेकशः, अनेकधा, वारंवारं, अभीक्ष्णं; 'how o.' कतिशः, कतिवारान्; 'as o. as- so o.' यतिवारं-ततिवारं.

Ogle, *s.* कटाक्षः, कटाक्ष-अपांग-दर्शनं, नयनोपांतविलोकितं, अर्धवीक्षणं, भ्रूविलासः. *-v. t.* कटाक्षेण ईक्ष् 1 A or अवलोक् 1 A, 10, तिर्यक्-साचि-दृश् 1 P.

Ogre, *s.* क्रव्याद् *m.*, दैत्यः, दानवः, राक्षसः.

Oil, *s.* तैलं, स्नेहः, अभ्यंजनं; 'pour o. on burning fire' क्षते क्षारं प्रक्षिप् 6 P; 'o.-bottle' कुतू *f.*; 'o.-cake' तैलकिट्टं, पिण्याकः, तिलकल्कं; 'o.-man' तैलिकः, तैलिन् *m.* तैल-स्नेह-कारः, चाक्रिकः; 'o.-mill' तैलयंत्रकी. *-v. t.* तैलेन लिप् 6 P or अंज् 7 P or दिह् 2 U. **-ed,** *a.* तैलाक्त, स्नेहाक्त, अभ्यक्त. **-y,** *a.* तैलमय (यी *f.*), सस्नेह, सतैल, तैलयुक्त-वत्, तैलाक्त; चिक्कण, मसृण, स्निग्ध, (fig. also).

Ointment, *s.* अंजनं, वि-,लेपः-पनं, प्र-अनु-लेपः, अभ्यंजनं, उपदेहः; 'perfumed o.' प्र-आलेपकी, वर्ति *f.*, वर्णकं.

Old, *a.* (Person) वृद्ध, स्थविर, प्रवयस्, परिणत, परिणतवयस्, जीर्ण, वयोवृद्ध, जरठ, जरत्, जरातुर, गतवयस्क, जीन, जरण, जरंड; 'to grow o.' जॄ 4, 9 P, ज्या 9 P, परिणम् 1 P; 'o. age' जरा, परिणामः, परिणति *f.*, वार्धकं-क्यं; वृद्धावस्था, वृद्धभावः, ज्यानि *f.*, जीर्णि *f.*; 'o. lady' जरती, स्थविरा, वृद्धा, पलिता, पलिक्नी; 'o. man' स्थविरः, जरठः, वृद्धः, जरन्, पलितः. 2 (Showing age) ex. by वर्ष, वत्सर, वर्षीण-य in comp; '8 years o.' अष्टवर्षीय, अष्टवर्ष-वर्षात्मक; 'a year o.' वर्षजात; '2 days o.' द्व्यहजात; 'how o. are you' किं ते वयःप्रमाणं, किंवर्षीयोसि. 3 (Not new) बहु-चिर-कालिक (की *f.*), चिर-दीर्घ-कालीन, चिरकाल-चिर-स्थायिन्, चिरंतन (नी *f.*); oft. by चिर in comp.; 'o. servant' चिरसेवकः, मूलभृत्यः, मौलः; 'o. friend' चिरमित्रं, चिरंतनसुहृद्. 4 जीर्ण, जर्जर, जर्जरित; 'o. cloth' चीरं, जीर्णवस्त्रं, पटच्चरं. 5 (Ancient) पुराण, प्राचीन, पूर्व, पूर्वतन (नी *f.*), प्राक्तन, पुरातन, प्रत्न, प्रत्न, पौराण (णी *f.*), प्राक्-पूर्व-कालीन, पुरावृत्त; 'of o.' 'in olden times' पुरा, पुराकल्पे, पूर्वं. **-en,** *a.* पुरातन, पुराण, प्राचीन. **-ish,** *a.* ईषद्वृद्ध.

Oleaginous, *a.* स्निग्ध, चिक्कण, मेदुर, मसृण

Oleander, *s.* प्रति(ती)हासः, करवीरः, शतप्रासः, चंडातः, हयमारकः.

Oleraceous, *a.* शाकविषयक.

Olfactory, *s.* नस्य, नासा in comp.

Olibanum, *s.* तुरुष्कः, पिंडकः, सिह्लः. यावनः; *See* **Incense** also.

Oligarchy, *s.* अल्पजनाधिपत्यं-प्रभुत्वं. **-ic,** *a.* अल्प-कतिपय-स्वामिक.

Olio, *s. See* **Medley.**

Olive, *s.* जितवृक्षः.

Omen, *s.* निमित्तं, शकुनः-नं, लक्षणं, चिह्नं, अजन्यं, पूर्वलक्षणं-चिह्नं, शुभाशुभलक्षणं; 'of good o.' शुभ, मंगल, सुलक्षण; 'good o.' सुलक्षणं; 'ill o.' दुश्चिह्नं, दुर्लक्षणं, अपशकुनः, अजन्यं, अपलक्षणं, अमंगलक्षणं. **-Ominous,** *a.* अनिष्ट or अशुभ-शंसिन् or आवेदक, दुर्लक्षण, अलक्षण. 2 शुभ-मंगल-शंसिन्. 3 शाकुनिक (की *f.*), शकुननिमित्त in comp. **-ly,** *adv.* अशुभलक्षणेन, दुर्लक्षणपूर्वं.

Omit, *v. t.* त्यज् 10, वि-परि-°, परि-त्यज् 1 P, उत्-,क्षिप् 6 P, मुच् 6 P, उत्सृज् 6 P,

अपास् 4 U, हा 3 P. **2** अतिक्रम् 1 U, 4 P, उपेक्ष् 1 A, लंघ् 1 A, 10, अतिचर् 1 P, अतिवृत् 1 A, लुप् c., न कृ 8 U or वि-धा 3 U or अनु-ष्ठा 1 P. **-Omission,** *s.* वर्जनं, त्यागः, उत्सर्गः, लंघनं, अतिक्रमः, अतिचारः, लोपः, उपात्ययः, 'o. to do something' अननुष्ठानं, अविधानं, उपेक्षा.

Omnifarious, *a.* सर्वविध-प्रकार.

Omnigenous, *a.* सर्वप्रकार-जातीय.

Omnipotent, *a.* सर्वशक्तिमत्, सर्वसमर्थ-शक्ति, अमित-अपार-शक्ति. **-Omnipotence, -cy,** *s.* सर्वशक्तित्वं, अपार-अमित-शक्ति *f.*, सर्वसामर्थ्यं, अनंतशक्तिः.

Omnipresent, *a.* सर्वगत, सर्वात्मक, सर्व-विश्व-व्यापिन्, विश्वात्मन्, विश्वरूप. **-Omnipresence,** *s.* सर्व-विश्व-व्याप्ति *f.*, विश्वात्मता, विश्वरूपता, सर्व-विश्वव्यापिता.

Omniscient, *a.* सर्वज्ञ, सर्वविद्-वेदिन्-बुध, सर्वदर्शिन्-साक्षिन्, विश्वनेत्र, त्रिकालज्ञ. **-Omniscience,** *s.* सर्वज्ञत्वं, सर्वज्ञानं.

Omnivagant, *a.* सर्वगत, सर्वगामिन्.

Omnivorous, *a.* सर्वभक्ष, सर्वभोजिन्.

Omphalic, *a.* नाभ्य, नाभि in comp.

Omphalocele, *s.* नाभिस्फोटः.

On, *prep.* Gen. ex. by loc., अधि pr., उपरि (with gen.). **2** (Time, place) by loc.; 'o. the shore' तीरे, तीरोपांते, उपतीरं. **3** (With verbs of motion) by loc. or instr., (स्कंधेन or स्कंधे छागं गृहीत्वा); 'go o. foot' पद्भ्यां गम् 1 P. **4** (Direction) by loc. or by तस्, त्र affixed; 'o. the left' वामतः; 'o. all sides' सर्वतः, सर्वत्र, समंततः. **5** (After) ex. by abl. or loc. abs.; 'o. his arrival' तस्मिन् आगते, तदागमनात्; or by gerund; 'o. hearing his speech' तस्य वचः श्रुत्वा. **6** (Concerning) विषय-संबंधिन् in comp. or by comp.; 'a work o. morals' नीतिग्रंथः; 'so o.' इत्यादि (*a.*); 'hence, o. thy life' स्वजीवितं यदि वांछसि तर्हि द्रागपसर, अपसरास्मात्स्थानाच्चो चेत् त्वं जीवितेन वियोक्ष्यसे; 'o. o., to the combat' नद्ध युद्धाय प्रयात. **-adv.** अग्रतः, अग्रे, प्र pr.; 'having clothes o.' परिहितवस्त्र. **-ward,** *a.* अग्रेसर (री *f.*), अग्रगामिन्; वर्धिष्णु. **-wards,** *adv.* अग्रे, अग्रतः, पुरतः.

On-dit, *s.* किल *ind.*; *See* **Rumour.**

One, *a.* एक; 'o. of two' एकतर; 'o. of many' एकतम; 'only o.' अनन्य; 'fixed on o. object' अनन्यविषय, अनन्यवृत्ति. **2** (Any) कश्चन, कोपि. **3** (Same) एक, तद् with एव; 'at o. time' युगपत्, समं, एककाले; 'having o. meaning' एकार्थ. **-s.** जनः, नरः, मनुष्यः; 'gen. not ex.; 'o. should always protect oneself' आत्मानं सततं रक्षेत्; 'o. by o.' एकैकशः, एकैकं, प्रत्येकं, पृथक्पृथक्; 'o. day' कदाचित्, कदापि काले; 'young or little o s.' शिशुजनः, बालाः; 'in o. way' एकधा; 'o.-self' आत्मन् *m.*, स्वयं *ind.*; 'o.'s own' स्व, निज, आत्मीय, स्वीय, आत्म in comp.; 'to be at o.' संमन् 4 A; 'o.-eyed' एकाक्ष, काण, एकाक्षिहीन; 'o.-sided' असम, एकपक्षीय, एकदेशीय; 'o. another' अन्योन्यं, परस्परं, इतरेतरं; 'to be o.-self again' प्रकृतिमापद् 4 A, संज्ञां लभ् 1 A; *See* 'come to senses' under **Sense**; 'to bring to o.-self' प्रकृतौ स्था c. (स्थापयति). **-ness,** *s.* एकत्वं, एकभावः, अद्वैतं, अभेदः, अविशेषः. **-Once,** *adv.* सकृत्, एकवारं. **2** (O. upon a time) एकदा, अथैकदा, अथ कदाचित्. **3** पुरा, पूर्वं, प्राक्काले; 'at o.' समं, युगपत्, एककाले, समकाले-लं; सद्यः, सपदि, तत्क्षणात्, तत्क्षणेन, तत्काले; 'all at o.' अकस्मात्, एकपदे; 'o. more' पुनरपि, भूयः, पुनः.

Oneirocritic,-al, *a.* स्वप्नविचारिन्.

Oneiromancy, *s.* स्वप्नार्थविचारः, स्वप्नार्थज्ञापनं.

Onerous, *a.* दुर्भर, गुरु, गुरुभार, दुर्वह, दुःसह.

Onion, *s.* पलांडुः, सुकंदकः.

Only, *a.* एक, एव, एकाकिन्, केवल, मात्र-मात्रक in comp., अद्वितीय, अनन्य; 'having that as the o. recourse' तदेकशरण, अनन्यगतिक. **-adv.** केवलं, एव, मात्र in comp.; 'not o. but' न केवलं followed by अपि or किंतु.

Onomatopoeia, *s.* अनुकारः, अनुकरणं.

Onset, *s.* आ-अभि-क्रमः-मणं, अवस्कंदः, अभिसंपातः, आपातः, अभिग्रहः, अभ्याघातः.

Onslaught, *s.* अभ्याघातः; *See* **Onset**

Ontology, *s.* सत्त्वविद्या, भूतविचारः. **-ist,** *s.* सत्त्वविद्याज्ञः.

Ooze, *v. i.* (शनैः) स्रु-आर्द्र-गल्- 1 P, स्यंद् 1 A, प्र-स्नु 2 P, री 4 A. **-v. t.** स्रु c., स्यंद् c., &c. **-s.** क्षरत्पंकः, मृदुमृत्तिका. **2** स्रवः, स्रुवः, धारा. **-ing,** *s.* स्यंदनं, क्षरणं, स्रवः. **-y,** *a.* सद्रव.

Opaque, *a.* प्रकाशाभेद्य, किरणाभेद्य; अस्वच्छ, कलुष, निष्प्रभ, सांधकार. **-ness, -Opacity,** *s.* अस्वच्छता, निष्प्रभता, कालुष्यं. **2** मूर्खत्वं.

Opal, *s.* पुलकः, विमलकः.

Open, *v. t.* (Door &c.) अपा-वि-वृ 5 U, उद्-घट् c., निरर्गलीकृ 8 U, (lotus) विकस् c., प्रबुध् c., भिद् 7 P or c., (सूर्यांशुभिर्भिन्नमिवारविंदं K. I. 32), स्फुट् c.; (eyes) उन्मील् c., उत्फल् c., उन्मिष् c.; (mouth) व्या-दा 3 P, जृंभ् c., उत्-विद्ृ; (hand) प्रसृ c., वितन् 8 U, विस्तृ c. **2**

वि-अंज् 7 P or c., विवृ, प्रकटीकृ, आविष्कृ, व्यक्तीकृ, प्रकाश् c., 'o. the heart', 'o. oneself' हृद्गतं निविद् c. 3 (As meaning) व्या-ख्या 2 P, व्याचक्ष् 2 A, व्याकृ, व्यक्तीकृ, विवृ. 4 छिद् 7 P, निर्भिद्. 5 शुध् c., वि-परि°. 6 प्रारभ् 1 A, प्रस्तु 2 U, प्र-उप-क्रम् 1 A. -v. i. उन्मील् 1 P, विकस् 1 P, स्फुट् 6 P, दल् 1 P, भिद् pass., फुल्ल् 1 P. 2 विस्तृ-विवृ- pass., वि-जृंभ् 1 A, प्रसृ c.-वितन्-pass.; (in other senses) pass. of roots in (v. t.). 4 (Ground) स्फुट्, विदल्, द्विधाभू, विद्-भिद्-pass. 5 प्रवृत् 1 A, प्रारभ् pass. -a. वि-अपा-वृत, असंवृत, उद्घाटित; (eyes) उन्मीलित, उन्मिषित; (hand) प्रसारित, वितत, विस्तृत, विस्तीर्ण; (mouth) विजृंभित, सजृंभ, उज्जृंभ, व्यात्त; (letter) उन्मुद्र, निरावेष्टन, अकोशस्थ. 2 निर्यंत्रण, असंबाध, निरर्गल, अनर्गल, अबद्ध, उत्-वि-शृंखल, निरवग्रह; वि-, शुद्ध, निर्विघ्न; See Free. 3 निर्व्याज, उत्तान, निष्कपट, सरल, ऋजु, निर्माय, उदार, शुद्धमति, विमलात्मन्; See Frank; 'o.-minded person' उत्तानहृदयः जनः. 4 सु-, प्रकाश, वि-,स्पष्ट, व्यक्त, प्रकट, अगूढ, अगुप्त. 5 निर्वृक्ष, अपादप; अनाश्रय. 6 गम्य, उपसर्पणीय; See Accessible, 'lays him o. to his enemy' शत्रुगोचरे (विषये) तं पातयति; 'o. to dispute' विवादास्पदं, विवादग्रस्त-a.; 'lay o' प्रकाश् c.; See (v. t.) 'o. air' अनावृतप्रदेशः-भूभागः; 'o. at one end' एकमुख; 'having gone out into the o. air' प्रकाशं निर्गतः (S. 4); 'o.-eyed' विवृताक्ष, उत्फुल्लनयन, सचेतन (fig.); 'o.-handed' उदार, मुक्तहस्त; 'o.-hearted' उदार, उत्तानहृदय, निर्व्याज; 'o.-mouthed' व्यात्तमुख. -er, s. उद्घाटकः, प्रकाशकः. -ing, s. विवरणं, विवृति f., उद्घाटनं; उन्मीलनं, विकासः, भेदः, स्फुटनं. 2 छिद्रं, रंध्रं, द्वारं, विवरः, स्फु(स्फो)टनं, भिदा. 3 प्रारंभः, उपक्रमः, प्रस्तावः, उपोद्घातः. -a. विकसत्, स्फुटत्. 2 प्रथम, आद्य, आरंभक. -ly, adv. प्रकाशं, सुस्पष्टं, व्यक्तं, परि-, स्फुटं. -ness, s. विवृतत्वं, विवृति f, निर्यंत्रणता, सारल्यं, निष्कापट्यं, दाक्षिण्यं, शुद्धमतिता, व्यक्तता, स्पष्टता, प्रकाशता, प्राकट्यं.

Opera, s. संगीतनाटकं.

Operate, v. i. गुणं आवह् 1 P, कार्य उत्पद् c. or दृश् c., फलं सं-पद् c. or साध् c., प्र-भू 1 P, प्रबलीभू; See Effect. 2 कृ 8 U, वि-धा 3 U, चेष्ट् 1 A, प्रवृत् 1 A प्र-यत् 1 A व्यापृ 6 A. 3 शस्त्रेण उपचर् 1 P or साध् c. -ion, s. क्रिया, कर्मन् n., कृति f., कार्यं, कृत्यं. 2 चेष्टितं, प्रवृत्ति f. उद्यमः, उद्योगः, प्रयत्नः, व्यापारः. 3 प्रवर्तकत्वं, हेतुता, कारणं, साधनं; 'mental o.' मनोव्यापारः; 'quick in o.' आशुकारिन्, सद्यःफल, आशुगुणावह. 4 (Surgical) शस्त्रक्रिया-कर्मन् n. शस्त्रोपायः, शस्त्रोपचारः. -ive, a. कर्मकारिन्, प्रवर्तक, प्रयोजक, कारणीभूत. 2 गुणावह, गुणकारिन्, सिद्धिकर (री f.), प्रबल, सप्रभाव, प्रभविष्णु, कार्यक्षम. -s. कर्मशिल्प-कारः, कारुः. -or, s. कारकः, कर्तृ m. प्रवर्तकः.

Operose, a. श्रम-कष्ट-साध्य.

Ophiology, s. सर्पविद्या.

Ophthalmia, s. नेत्राभिष्यंदः.

Opiate, a. निद्रावह, निद्रा-स्वाप-कारिन्, स्वापन. -s. निद्रावहं औषधं, स्वापनं.

Opine, v. i. मन् 4 A, तर्क् 10; See Think. -Opinion, s. मतं, मति f., तर्कः, बुद्धि f., बोधः, अभिप्रायः, आशयः; 'such is my o.' इति मे मतिः; 'difference of o.' मति-(त)भेदः, विप्रतिपत्ति f., वैमत्यं; 'regard for public o.' लोक or जन-लज्जा or भयं; 'secure the good o. of your husband' भर्तृबहुमता भव (S. 4). -ated, -ative, a. स्वमताभिमानिन्, मताग्रहिन्, दुराग्रहिन्.

Opium, s. अहिफेनं, अफेनं.

Opponent, a. विरुद्ध, प्रतिकूल, वि-प्रति-पक्ष. वैरिन्. -s. शत्रुः, अरिः, वैरिन्, वि-प्रति-पक्षः; प्रतियोद्धृ, प्रतियोगिन्, प्रतिरोधकः all m.

Opportune, a. समयोचित, प्राप्तकाल, कालयोग्य, प्रस्तावसदृश (शी f.), प्राप्तावसर, सामयिक-प्रास्ताविक- (की f.). -ly, adv. प्राप्तकालं, काले, स्थाने, यथासमयं, यथावसरं, प्रस्तावसदृशं, कालोचितं. -ness, s. कालोचित्यं, प्रस्तावयोग्यता. -Opportunity, s. प्रस्तावः, अवकाशः, अवसरः, कालः, समयः, प्रसंगः, वेला, कार्यकालः, योगः. 2 साधनं, उपायः, प्रयुक्ति f.: 'lose an o.' कालं क्षिप् 6 P or हृ 1 P; 'seizing an o.' अवसरं गृहीत्वा, गृहीतावसर, लब्धावकाश; 'to await an o.' अवसरं प्रति-पा c. (पालयति).

Oppose, v. t. वि-नि-प्रति-रुध् 7 U, प्रतिबंध् 9 P, प्रतिकृ 8 U, प्रतिकूलयति (D.), प्रत्यव-स्था 1 A, वि-प्रति-हन् 2 P, बाध् 1 A, निवृ c.; (in fighting) प्रतियुध् c.; संमुखी-अभिमुखी-कृ 8 U or भू. -ed, a. विरुद्ध, विपरीत, प्रतिकूल, विप्रतिपन्न, बाधित, वारित, असंमत, विद्विष्ट, 'o. to the practice of the world' लोकाचारविरुद्ध, लोकासंमत, लोकविद्विष्ट. 2 इतर in comp., 'o. to false' मिथ्येतर. -er, s. विरोधकः, प्रतिहंतृ m. -Opposite, a. सं-प्रति-अभिमुख (खी f.), संमुखस्थ. 2 विरुद्ध, विरोधिन्, विपरीत, प्रतिकूल, वि-प्रति-पक्ष, प्रतिद्वंद्विन्, विपर्यस्त, व्यत्यस्त, इतर in comp.

'o. of natural' सहजेतर; स्वभेतर, &c. 3 पर, अपर, अंतर in comp.; 'the o. bank' पारं, तीरांतरं, अपरतीरं. -s. विपर्ययः, व्यत्यासः. विपरीतं; by (a.). -ion, s. वैपरीत्यं, प्रातिकूल्यं, विरोधः, विपक्षता, विपर्य-(र्या)यः, व्यत्ययः, व्यत्यासः, विपर्यासः. 2 विरोधः, प्रतिक्रिया, प्रतिबंधः, प्रतियोगः-यत्नः, व्याघातः, बाधः-धा. 3 विरोधकजनाः, प्रतियोगिपक्षः, विरोधिजनवर्गः. 4 विरुद्ध-द्वैध-भावः. वरं. -ly, adv. सं-अभि-मुखं, विपरीतं. प्रतिकूलं, विपर्ययेण.

Oppress, v. t. पीड् 10, अर्द् 1 P or c., उपद्रु 1 P. बाध् 1 A, नि-अप-कृ 8 U, विप्र-कृ, उपप्लु 1 A, उप मृद् 9 P or c., कृश् c., अभिद्रुह् 4 P, अभिभू 1 P. -ion, s. पीडा, पीडनं. बाधः-धा, अर्दनं, उपमर्दः, उपप्लवः, उपद्रवः, नि-विप्र-अप-कारः, मेहर्षं, कार्श्यं. -ive, a बाधक, पीडाकर (री f.), उपप्लाविन्, उपद्राविन्, पीडाप्रद, अपकारक; निष्ठुर, अतिक्रूर, क्लेशद. 2 अतिभारवत्. -or, s. प्रजापीडकः, उपप्लावकः, उपद्राविन् m., अत्याचारः, निष्ठुरः, क्रूरचरितः.

Opprobrium, s. निंदा, गर्हा, कुत्सा, तिरस्कारः, अपवादः, अवज्ञा, परिभवः, वाच्यता, धिक्कारः. -**Opprobrious,** a. गर्ह्य, निंदात्मक, गर्हारूप, निंदा-गर्हा-अर्थक; परुष, मुखर, द्वेष्य. -ly, adv. सापवादं, सतिरस्कारं. -ness, s. गर्ह्यता, निंदकत्वं.

Oppugn,-er, *See* **Oppose** &c.

Optative, a. इच्छार्थक.

Optic,-al, a. चाक्षुष (षी f.), चक्षुः-नेत्र in comp. 2 दृक्शास्त्रसंबंधिन्. -s. चक्षुरिंद्रियं, दृगिंद्रियं. -**Optics,** s. दृग्विद्या-शास्त्रं.

Optimacy, s. कुलीनवर्गः-जनाः.

Optimism, s. उत्तमता, उत्कृष्टता.

Option, s. अभि-,रुचि f., इच्छा, कामः. अभिलाषः, ईप्सितं; विकल्पः, विभाषा (in grammar); 'it is left to your o' अत्र स्वच्छया वर्ततां भवान्, यथाभिलाषं क्रियतां. -al, a. वैकल्पिक- ऐच्छिक- (की f.), काम्य, सविकल्प, यथाकाम, स्वच्छंदाधीन, स्वेच्छातंत्र. -ally, adv. विकल्पेन, अन्यतरस्यां, (इकोऽन्यतरस्यां), वा, विभाषया.

Opulent, a. श्रीमत्, धनिन्, धनाढ्य, वित्तवत्, धन-वित्त-संपन्न, धनिक, समृद्ध, संपन्न, धनेश्वर, बहुधन. -**Opulence,** s. विभवः, ऐश्वर्य, समृद्धि f.

Or, *conj.* अथवा, यद्वा, वा (never at beginning) repeated after each word, or after the last; (in questions) नु, (स्वप्नो नु माया नु मतिभ्रमो नु); उत, आहो, आहोस्वित् (correl. of किं 'whether'). 2 अन्यथा, इतरथा, अथवा, नोचेत्.

Oracle, s. दैवी वाक्, देव-आकाश-वाणी, आकाशभवा-अशरीरिणी-सरस्वती. 2 प्रश्न-देवता-दैवः. 3 प्रश्न- शकुन-स्थानं. 4 प्रमाणं, आप्तः, प्रमाणपुरुषः; आप्तवचनं. -**Oracular,** a. देववाणीतुल्य, प्रमाणभूत, आप्त, प्रामाणिक (की f.).

Oral, a वाचिक (की f.), उक्त, अलिखित; 'o. message' वाचिकं. -ly, adv. वाचा मुखद्वारा, अलिखितं.

Orange, s. नारंगः, नागरंगः, ऐरावतः, मधुकर्कटी, भूमिजंबुका; (fruit) नारंगफलं; 'o.-colored' पिंगल, कौसुंभ (भी f.). -**Orangery,** s. नागरंग-वाटिका.

Oration, s. वाक्प्रबंधः, सालंकारं वचनं, प्रवचनं, सरस्वतीनिष्यंदः (fluent o.). -**Orator,** s. प्र-,वक्तृ m., वाक्शौण्डः-चतुरः, प्रवचनपटुः, सहृक्तृ m. वाक्पटुः, वाग्मिन् m., वागीशः, वाक्पंडितः-विशारदः, सभापंडितः. -ical, a. वाक्चातुर्यमय (यी f.), सालंकार, वागलंकारमय. -y, s. वाग्मिता, वाक्पाटवं-चातुर्यं, सुवक्तृत्वं, वाक्शक्ति f., वक्तृत्वं, सभापांडित्यं. 2 प्रार्थनागारं, उपासनास्थानं, भजनालयः. -**Oratorio,** s. तालबद्धं धर्मकीर्तनं. 2 **Oratory** q. v.

Orb. s. मंडलः-लं, बिंबः-बं, वर्तुलं, चक्रं, वृत्तं, गोलः-लं; 'the moon with entire (undiminished) o.' पूर्ण-अविकल-मंडल-चंद्रः, अखंडकलः शशी (Mal. 2). -ed, -**Orbicular,** a. मंडलाकार, वर्तुल, गोलाकृति -**Orbiculate,** s. वर्तुलं. -a. वर्तुल; *See*(s.).

Orbit, s. कक्षा-क्षः, ग्रहपथः-मार्गः.

Orchard, s. वाटिका, वाटः-टी, उपवनं, वृक्षोद्यानं, वृक्षवाटिका; 'fruit o.' फलवाटिका.

Orchestra, s. वादित्रस्थानं-स्थलं. 2 वादकसमूहः, वादित्रगणः.

Ordain, v. t. वि-धा 3 U, आदिश् 6 P, निर्दिश्, संस्थव-स्था c. (स्थापयति), प्र-परि-क्लृप् c; प्रचुद् 10, वच् 2 P, स्मृ 1 P; 'o. ed by Sastras' शास्त्रोक्त, शास्त्रविहित-स्मृत, शास्त्रनिर्दिष्ट, &c. 2 (अधिकारे) नियुज् 7 A, 10, अधिकृ 8 U, or c., अभिषिच् 6 P, व्या-दिश्; (religiously) दीक्ष् 1 A, धर्मकर्मणि नियुज्. -er, s. प्रकल्पकः, संस्थापकः, प्रचोदकः.

Ordeal, s दिव्यं, सत्यं, परीक्षा, प्रमाणं; 'o. by fire' कोशः-षः, तप्तदिव्यं; 'subjecting oneself to o.' दिव्यग्रहणं; 'trying o.' (fig.) तत्त्वनिकषा आपद्.

Order, v. t. आदिश् 6 P, निर्-नि-समा-व्या दिश्, शास् 2 P, आ-ज्ञा c. (ज्ञापयति), प्रचुद् 10, 2 वि-धा 3 U, प्रणी 1 P, निर्बंधू c.; *See* **Manage.** 3 परिक्लृप् c., क्रमेण विन्यस् 4 U or c. or स्था c. (स्थापयति) or वि-धा, संवि-धा, व्यव-स्था c., वि-,रच् 10;

व्यूह् 1 U. 4 Ordain, q. v. –*s.* आज्ञा, आ-नि-देशः, निर्देशः, शासनं, नियोगः; 'written o.' आज्ञापत्रं; 'what are your o.s' को नियोगोऽनुष्ठीयतां; 'your Majesty's o.s will be obeyed' यथाज्ञापयति देवः. 2 प्र-,चोदनं-ना, विधिः, नियमः, विधानं, प्रेरणा, वचनं. 3 क्रमः, अनुक्रमः, परिपाटि-टी *f.*, आनुपूर्व्यं-र्वी, पर्यायः, परंपरा, पारंपर्यं, आवृत् *f.*; व्यवस्था, विन्यासः, विरचनं-ना, संविधानं; 'natural o.' आनुलोम्यं; 'inverted o.' 'reverse o.' प्रातिलोम्यं, व्युत्क्रमः, व्यतिक्रमः, विपर्ययः, विपर्यासः, व्यत्यासः, व्यत्ययः; 'o. of battle' व्यूहः, सैन्यरचना, बलविन्यासः; 'natural o. of words' अन्वयः; 'in natural or direct o.' अनुलोम-मतः; 'in inverted o.' प्रतिलोम-मतः; in good o.' सुस्थित, सुरक्षित, सुविहित; 'in o.' सुविन्यस्त, सुविरचित, व्यवस्थित, क्रमेण स्थापित; (*adv.*) क्रमेण, क्रमशः, यथाक्रमं, क्रमानुरूपं, अनुपूर्वशः, आनुपूर्व्येण, परिपाट्या; 'in o. to' ex. by अर्थं-र्थे in comp.; by dat. or by inf.; 'out of o.' अव्यवस्थित, भग्नक्रम, अस्वस्थ. 3 मार्गः, स्थिति *f.*, रीति *f.*, पद्धति *f.*, आचारः, नियमः; 'not breaking the (established) o.' स्थितेरभेत्ता (R. III. 27) स्थित्यै दंडयतो दंड्यान् (R. I. 25) 'for maintaining o. &c.'; 'breaking the o.' स्थितिभेदः, अतिपातः, पर्ययः, उपात्ययः 5 गणः, वर्गः, वर्णः, जाति *f.*; 'the lower o.s' अवर-अधम-वर्णाः, अंत्यवर्गाः, अधमजातीयाः. 6 आश्रमः, वर्णाश्रमः; 'head of a religious o.' आश्रमगुरुः. –er, *s.* आज्ञापकः, आदेष्टृ *m.*; शास्तृ *m.* –less, *a.* क्रमहीन, शून्य, अक्रम, अनवस्थित. –ly, *a.* व्यवस्थित, यथाक्रम, क्रमानुगत, सक्रम, अनुपूर्व. –*adv.* यथाक्रमं, पर्यायेण, क्रमशः.

Ordinal, *a.* क्रमवाचक. –*s.* क्रमिकसंख्या. 2 विधिसंहिता.

Ordinance, *s.* नि-बंधः, मर्यादा, कल्पः, प्र-,चोदनं-ना, स्थिति *f.*, धर्मशास्त्रविधिः-मर्यादा, नियमः, सूत्रं. 2 नि-आ-देशः, शासनं, नियोगः.

Ordinary, *a.* प्रचलित, प्रसिद्ध, प्रायिक (की *f.*), लोकप्रसिद्ध. 2 साधारण (णी *f.*), सामान्य, व्य(व्या)वहारिक-आचारिक-नैयमिक-(की *f.*), नित्य, यथाव्यवहार, यथाप्रवृत्ति; 'something more than o.' विशेषः. 3 सामान्य, मध्यम, प्राकृत, अवर, नीतिविशिष्ट; 'an o. woman' नातिरूपवती स्त्री, सामान्यलावण्योपेता. –*s.* धर्माध्यक्षः. 3 साधारणभोजनस्थानं –ily, *adv.* सामान्यतः, साधारणतः, प्रायः, प्रायेण, प्रायशः.

Ordinate, *a.* यथानुक्रम, अनुपूर्व. –ion, *s.* नियोजनं, कल्पनं, नियोगः. 2 दीक्षा; *See* **Ordain.**

Ordnance, *s.* युद्धायसामग्री, युद्धयंत्रसमूहः.

Ordure, *s.* पुरीषं, विष्ठा, उच्चारः; *See* **Dung;** 'to void o.' पुरीषं उत्सृज् 6 P or उच्चर् 1 P.

Ore, *s.* धातुः, खनिज-असंस्कृत-धातुः.

Organ, *s.* इंद्रियं, करणं, हृषीकं, विषयिन् *n.*; (of action) साधनं, करणं, उपकरणं, कर्मसाधनं, कर्मेंद्रियं; 'intellectual or internal o.' धींद्रियं, अंतरिंद्रियं. 2 द्वारं, मुखं, साधनं. 3 वंशी. –ic,–ical, *a.* इंद्रियसंबंधिन्, इंद्रियमय (यी *f.*)-विशिष्ट, इंद्रियोत्पन्न, सकरण; इंद्रिय in comp. –ism, *s.* रचना, घटना. –ist, *s.* वंशीवादकः. –Organize, *v. t.* निर्मा 3 A, 2 P, सृज् 6 P, क्लृप् c., वि-रच् 10, घट् c. (घटयति). 2 वि-धा 3 U, संवि-धा, विन्यस् 4 U, क्रमेण स्था c. (स्थापयति), व्यव-स्था c., व्यूह् 1 U. 3 इंद्रियैः संयुज् 7 U, 10. –ation, *s.* निर्माणं, सृष्टि *f.*, घटनं-ना, विन्यासः, व्यूहः-हनं, संविधानं. 2 भावविरचनं-कल्पना-विन्यासः. 3 सेंद्रियता.

Orgasm, *s.* आ-सं-वेगः, क्षोभः, उत्तापः, अत्यंतावेशः.

Orgy, *s.* रात्र्युत्सवः, नैशोत्सवः, महर्षः, प्रमोदः.

Orient, *a.* उज्ज्वल, भास्वत्; *See* **Bright.** 2 उद्यत्, उदयमान. –*s.* प्राची, पूर्वदेशः. –al, *a.* पौरस्त्य, प्राच्य, पूर्वदेशीय, पूर्व, प्राचीन. –*s.* पूर्वदेशवासिन् *m.* –alist, *s.* पूर्वदेशीयभाषाज्ञः.

Orifice, *s.* मुखं, छिद्रं, रंध्रं, द्वारं, सुषिरं, विवरं; 'o. of the ear' श्रवणः.

Origin, *s.* मूलं, प्रभवः, आ-प्रा-रंभः, उत्पत्ति *f.*, उद्भवः, उद्गमः, संभवः, जन्मन् *n.*, जाति *f.*, आदिः, योनि *f.*, बीजं, हेतुः, आदिकारणं, उत्पत्तिस्थानं. 2 प्रयोजकः, प्रवर्तकः; 'of low o.' हीनजाति-जन्मन्, दुर्योनि; 'of good o.' मौल (ली *f.*), उत्कृष्टजाति. –al, *a.* मौल, प्रथम, आदिम, आद्य, पूर्व, आदि-मूल-in comp.; 'o. passage' मूलं, मूलवचनं. 2 अपूर्व, अपूर्वकल्पित, अचिंतितपूर्व, स्वतः-स्वयं-कल्पित. 3 अपूर्वरचक, स्वतः कल्पक. –*s.* मूलं, आदर्शः, मूलपत्रं-ग्रंथः-लेखः; *See* (*s.*). –ality, *s.* अपूर्वरचनाशक्ति *f.*, कल्पकत्वं-ता, अपूर्वकल्पनासामर्थ्यं, कल्पनाशक्तिः. 2 अपूर्वता. –ally, *adv.* आदौ, प्रथमं, प्रथमतः, प्रारंभे, मूलतः. –ate, *v. t.* (प्रथमं) उत्पद् c., जन् c. (जनयति), उद्भू c., सृज् 6 P, क्लृप् c., प्रवृत् c., निर्मा 3 A; प्रारभ् 1 A, उपक्रम् 1 A. –*v. i.* (प्रथमं) उत्पद् 4 A, जन् 4 A,

प्र-उद्-सं-भू 1 P, प्रसू 1 P; उद्-इ 2 P. उद्-गम् 1 P, प्रवृत् 1 A, उत्था 1 P; ex by (s.) or by 'Arise', q. v. **-ation,** s. प्रारंभः, प्रथमोद्भवः. **-ator,** s. प्रवर्तकः उत्पादकः, कल्पकः, योजकः, आरंभकः, निर्मातृ m. also ex. by (s.).

Orion, s. मृगशीर्षं.

Orison, s. प्रार्थना, स्तवः, स्तुति f., उपासना स्तोत्रं.

Ornament, s. अलंकारः, वि-,सुवर्णं, आभरणं, मंडनं; (decoration) अलंकरणं भूषा, अलंक्रिया, संस्कारः, परिष्कारः, परिकर्मन् n., प्रतिकर्मन् n. प्रसाधनं कल्पना, लज्जा, नेपथ्यं, शोभा; (fig.) ललामं, अवतंसः, अलंकारः, तिलकः; 'o. to the Kshatriya family' क्षत्रियकुलावतंसः; आश्रमललामभूता; पंडितकुलतिलकः &c. **-v.** t. अलंकृ 8 U, परिष्कृ, मंडू 10, भूष् 10, प्रसाध् c., शुभ् c., रंज् c. **-al,** a. शोभावह, वि-, भूषक, शोभावह, शोभा-भूषा-कर (री f.), अलंकरिष्णु; or by (s.). **-ally,** adv. विभूषणार्थं. **-ation,** s. अलंकरणं, मंडनं; रंजनं.

Ornate, a. कांतिमत्, विचित्र, शोभित, वि-,भूषित; सालंकार, अलंकारमय (यी f.), अलंकृत; कृतालंकार. **-ly,** adv. सालंकारं, शोभापूर्वं.

Ornithology, s. पक्षिविद्या. **-ist,** s. पक्षिविद्याज्ञः.

Orphan, s., a. अनाथः, मातापितृरहितः-हीनः, गतमातृकः, गतपितृकः **-age,** s. अनाथता. **2** अनाथाश्रयः, अनाथालयः.

Orpiment, s. (Yellow) पिंजरं, पीतनं, तालं, आ(अ)लं, हरितालकं.

Orrery, s. ग्रहमालानुकरणयंत्रं.

Orris, s. वचा, उग्रगंधा, षड्गंधा, गोलोमी, शतपर्णिका; (white) हैमवती, श्वेतवचा.

Orthodox, a शास्त्रीय, शास्त्रसंमत, शास्त्रमतानुसारिन्, धर्मपरायण, सत्यधर्मानुरोधिन्. **-y,** s. शास्त्रानुसारः, शास्त्रमार्गावलंबनं, धर्मपरायणता.

Orthoepy, s. शुद्धोच्चारः-रणं. **-ist,** s. शुद्धोच्चारणविद् m.

Orthogon, s. समचतुरस्रं. **-al,** a. समकोणाकृति.

Orthography, s. अक्षर-वर्ण-विन्यासः, वर्णविन्यासशास्त्र-विचारः.

Orts, s. See **Offal.**

Oscillate, v. i. दोलायते (D.), प्रेंख् 1 P, इतस्ततः चल् 1 P or कंप् 1 A or स्फुर् 6 P or स्पंद् 1 A; See **Waver. -ion,** s. आंदोलनं, प्रेंखणं, इतस्ततः चलनं, गतागतं. **-ing,-ory,** a. दोलायमान, स्पंदमान, स्फुरित.

Oscitant, a. वि-,जृंभमाण, जृंभित. **2** निद्रालु, तंद्रालु. **-Oscitate,** v. i. वि-,जृंभ् 1 A.

Osprey, s. कुररः-री, उत्क्रोशः.

Osseous, a. अस्थिमय (यी f.). **-Ossicle,** s. अस्थिकं. **-Ossify,** v. t. अस्थिसात्कृ 8 U. **-v.** i. अस्थिसाद् भू 1 P. **-Ossuary,** s. अस्थिस्थानं.

Ostensible, a. व्यक्त, सुप्रकाश, प्रकट, प्रसिद्ध, अगूढ. **-Ostensibly,** adv. प्रकाशं-शतः, प्रकटं, अगूढं.

Ostentation, s. आडंबरः, दंभः, दर्पः, विकत्थनं, आत्मश्लाघा. **-Ostentatious,** a. आडंबर-प्रिय-शील, दंभशील, दांभिक (की f.); आत्मश्लाघिन्. **-ly.** adv. साडंबरं, दंभपूर्वं, सदंभं.

Osteocope, s. अस्थिवेदना.

Osteology, s. अस्थि वर्णन-विद्या.

Ostler, s. See **Groom.**

Ostracise, v. t. वि-निर्-वस् c. **-Ostracism,** s. विवासनं, निर्वासनं.

Other, a. अन्य, अपर, इतर, पर, अन्यतर (pron. a.) अंतरं in comp. **2** भिन्न, व्यतिरिक्त. **3** अव-,शिष्ट 'the o. s' अपरे, अन्ये, इतरे, शिष्टजनाः; 'at o. times' अन्यदा; 'the o. day' अन्येद्युः, नातिचिरं. **-wise,** adv. अन्यथा, इतरथा. **2** वा, नो-चेत्, अन्यथा, अथवा.

Otiose, a. अनवहित. निरुत्साह, प्रमत्त, अव्यापृत.

Otter, s. उद्रः, जलमार्जारः.

Ought, v. Ex. by अर्ह् 1 P; gen. by pot. pass. part. or by pot.: See **Must.**

Ounce, s. टंकद्वयं, पणार्धं. **2** द्वीपिन् m.

Oust, v. t. निःसृ c., निष्कस् c., अपास् 4 U, निराकृ 8 U, बहिष्कृ; See **Dispel, Drive out.**

Out, adv. बहिः (with abl.); 'gone o. बहिर्गत; (with verbs) ex. by निर्, वि, अप, प्र, बहिः; 'to be o.' प्रकाशतां गम् 1 P, प्रकाशीभू 1 P; 'the secret is o.' रहस्यं भिन्नं. **2** निर्वापित-a.; 'to be o.' प्रशम् 4 P, निर्वा 2 P; 'the lamp was o.' दीपः प्रशशाम-निर्ववौ. **3** क्षीण-विगत-अवसित-a. **4** अंतं-शेषं-यावत्, आ-अवसानात्; 'hear me o.' शृणु मे सावशेषं वचः (M. 4); 'let me speak o.' वचः समापयानि तावत्. **5** उच्चैः, उच्च-तार-स्वरेण, मुक्तकंठं. **6** व्यक्तं, प्रकटं, स्पष्टं, स्फुटं; 'o. upon (with) the thief' दूरीक्रियतां-निःसार्यतां-असौ चौरः; 'o. of' बहिः with abl., or by abl.; (among) मध्यात् with gen., or by gen. or loc.; (exclusion) ex. by अ, निर्, वि, अप, गत, नष्ट, त्यक्त in comp.; 'o. of the road' त्यक्त-भ्रष्ट-मार्ग; 'o. of one's mind' हत-नष्ट-बुद्धि, बुद्धिभ्रष्ट; 'o. of place' अस्थान, अनुचित;

'o. of order' उत्सूत्र, क्रमहीन, विधिविरुद्ध, अव्यवस्थित; 'o. of tune' अप-विस्वर; (showing motive) ex. by instr. or abl.; (beyond) अतीत, अगोचर in comp., अति pr.; 'o. of sight' नयनविषयातीत, दृग्गोचर, अंतर्हित; 'o. of one's reach' अविषय, अप्राप्य; 'o. of one's power' अतिशक्ति; 'o. of use' गत-लुप्त-व्यवहार, अव्यवहारित; 'o. of fashion' लोकाचारविरुद्ध; 'o of time' गतकाल, कालातीत; 'o. of hope' गताश, निराश; 'o. of man's strength' अतिमानुष; 'to pass o. of sight' नयनविषयं अति-इ 2 P or अतिक्रम् 1 U, 4 P; stand o. of hearing' श्रवणागोचरास्थित; 'o. of employment' क्षीणवृत्ति, निर्व्यापार, नियोगहीन; 'o. of office' भ्रष्ट-च्युत-अधिकार, अधिकारभ्रष्ट-च्युत; 'o. of hand' सद्यः, सपदि; 'o.-door' द्वारबहिःस्थ, बहिःप्रदेशकृत; 'o.-house' उपगृहं, बहिर्गृहं. -*interj.* अपेहि, अपसर, धिक् (with acc.). -er, -ermost, *a.* बाह्य, बहिःस्थ, बहिर्भव, बहिर्वर्तिन्, बहिः in comp. -most, *a.* अतिबाह्य. -ward, *a.* बाह्य, बहिः in comp. 2 दृश्य, आविर्भूत, प्रकट, प्रकाश. 3 अवास्तव (वी *f.*), मिथ्या-मृषा in comp. -*adv.* (O. ४) बहिः, बहिर्भागे-देशे. -wardly, *adv.* बाह्यतः, बहिः, बहिर्भागे. 2 अवस्तुतः, मृषा, मिथ्या, कृतकं, कृत्रिमं.

Out-act, *v. t.* अत्याचर् 1 P, अतिकृ 8 U.

Out-balance, *v. t. See* **Outweigh.**

Out-bid, *v. t.* अधिकमूल्यदानेन अभि-भू 1 P.

Outbreak, Outburst, *s.* उद्भेदः, निर्गमः, प्रादुर्भावः, उदयः, आस्फोटः.

Outcast, *s.* निष्कासितः, बहिष्कृतः, जातिबाह्यः-भ्रष्टः, जाति-वर्ण-पतितः, अपांक्तः, अपांक्तेयः, पतितः. 2 चं (चां)डालः, अपसदः, हीनजातिः-वर्णः, विहीनः, निवर्णः, नीच-अधम-वर्णः; *See* **Mean.**

Outcome, *s.* फलं, परिणामः, उदर्कः.

Outcry, *s.* उत्क्रोशः, आक्रोशः, कोलाहलः, कलकलः, तुमुलं, संहूति *f.*, उद्घोषः; 'popular o.' जनरवः संहूतिः. 2 आर्तनादः-रवः.

Outdo, *v. t.* अति-शी 2 A, अतिक्रम् 1 U, 4 P; *See* **Excel.**

Outfit, *s.* सज्जा, सामग्री, उपकरणसंभारः, परिच्छेदः.

Outgo, *v. t.* अति-इ 2 P, अतिचर् 1 P, अतिगम् 1 P. -ing, *s.* व्ययः, अपचयः, क्षयः, विनियोगः.

Outgrow, *v. t.* अतीत्य वृध् 1 A, अति-वृध्.

Outing, *s.* भ्रमणं, पर्यटनं, विहारः.

Outlander, *s.* वैदेशिकः.

Outlandish, *a.* विजातीय, विदेशीय, विदेशज, पर-अन्य-देशीय. 2 असंगत, ग्राम्य, अशिष्ट, असभ्य.

Outlaw, *s.* निषिद्धाम्बुदकः, न्यायरक्षणभ्रष्टः. -*v. t.* न्यायाद् बहिष्कृ 8 U, अम्बूदकदानं निषिध् 1 P.

Outlay, *s.* (द्रव्यादेः) व्ययः, अपचयः, विनियोगः, धनोत्सर्गः, द्रव्यव्ययः.

Outlet, *s.* द्वारं, मुखं, निर्गमः, परि(री)वाहः, उच्छ्वासः, निर्गमद्वारं; स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते (K. iv. 26) 'finds an o.' &c.

Outline, *s.* बाह्यरे(रे)खा, आकारमात्रं, वस्तुमात्रं. 2 पांडुलेख्यं, चित्रारंभः. 3 स्थूलवर्णनं, असूक्ष्मविचारः.

Outlive, *v. t.* अति-जीव् 1 P.

Outlook, *s.* अवेक्षणं, अवेक्षा.

Outlying, *a.* दूरस्थ. 2 असंसक्त.

Outmanœuvre, *v. t.* अभि-भू 1 P, अति-रिच् 7 U.

Outmarch, *v. t.* अति-या 2 P, अति-या.

Outnumber, *v. t.* संख्यया अति-शी 2 A. अधिकसंख्य-*a.* भू 1 P, अधिकीभू.

Outpour, *v. t.* वृष् 1 P, निषिच् 6 P, उत्सृज् 6 P. -s., -ing, *s.*, वर्षः-र्षणं, उत्सर्गः.

Output, *s.* फलं, उत्पन्नं, लाभः.

Outrage, *s.* साहसं, आधर्षः-र्षणं, बलात्कारः, अन्यायः, अत्याचारः, उपसर्गः, उपद्रवः, अभि-,द्रोहः, उपघातः, प्रमाथः, मर्यादातिक्रमः. 2 न्यक्कारः, धिक्कारः, अवलेपः, उत्सेकः. -*v. t.* कलंकयति (D.); (a woman) सतीत्वाद् भ्रंश् c. or च्यु c., दुष् c. (दूषयति) आधृष् c.; उपमृद् c., प्रमथ् 9 P or c., उपद्रु 1 P, अभिद्रुह् 4 P, न्यक्कृ 8 U, धिक्कृ; *See* **Insult** also. -ous, *a.* दारुण, घोर, उग्र, अनिष्ठुर, उद्दंड, प्रमाथिन्, अतिसाहसिक (की *f.*), राक्षस (सी *f.*), निर्लज्ज, वीतत्रप, अतिदुराचार. -ously, *adv.* घोरं, दारुणं, अत्याचारपूर्वं, अतिसाहसेन. -ousness, *s.* दारुणता, &c.

Outreach, *v. t.* अतिगम् 1 P, अति-इ 2 P.

Outrider, *s.* अश्वारूढः परिचरः.

Outright, *adv.* सद्यः, सपदि, तत्क्षणं-णे, अविलंबितं. 2 सर्वथा, साद्यंतं, सम्यक्, सु-अति pr. 3 स्पष्टं, व्यक्तं, अवक्रं.

Outroot, *v. t. See* **Eradicate.**

Outrun, *v. t.* अतिधाव् 1 P, धावने अति-शी 2 A.

Outset, Outstart, *s.* प्रारंभः, उप-प्र-क्रमः, आदिः, उपोद्घातः; 'at the very o.' प्रथममेव, आदावेव, उपोद्घातरूपेण.

Outshine, *v. t.* अधिकं प्रकाश् 1 A or द्युत् 1 A, अति-शुभ् 1 A or रुच् 1 A.

Outside, *s.* बहिर्भागः, बहिःप्रदेशः, बाह्यभागः; oft. by बहिः, 'charming on the o. only' बहिरेव मनोरम. 2 परमावधिः. -*adv.* बहिः (with abl.), बहिर्भागे. -*a.* बाह्य, वहिस्थ, बहिः in comp. -er, *s.* बहिर्देशवासिन् *m.*, अन्यदेशीयः, पारदेशिकः; *See* **Foreigner.**

Outskirt, *s.* उपांतः, पर्यंतः, सीमा, पारंसर, प्रांतः, उत्संगः; 'o. of a village' ग्रामांतः, उपकंठं; 'o. of a forest' वनांतः.

Outspoken, *a.* स्पष्ट-स्फुट-वादिन्, स्फुटवक्तृ; *See* **Candid, Frank.**

Outspread, *v. t.* विस्तृ c., प्र-वि-सृ c., वितन् 8 U.

Outstanding, *a.* अशोधित, अनिष्पन्न, अनिस्तीर्ण.

Outstretch, *v. t.* प्र-सृ c., उच्छ्रि 1 U or c.; oft. by उत् in comp.; 'with the neck o. ed' उत्कंधर; 'with hands o. ed as far as the wrist' आमूर्धभागोत्थितैः करतलैः (S. 4).

Outstrip, *v. t.* अति-इ 2 P, अतिक्रम् 1 U, 4 P. अतिवृत् 1 A, अतिचर् 1 P, लंघ् 1 A, 10; oft. by अति in comp. 'o. s the senses' इंद्रियगोचरो न वर्तते, अतींद्रियः.

Outvie, *v. t.* *See* **Excel.**

Outweigh, *v. t.* भारेण-भारतः-अतिरिच् pass. (with abl.), अधिकभारीभू 1 P; (Excel, q. v.).

Outwit, *v. t.* प्र-तॄ c., वंच् 10, वि-प्र-लभ् 1 A; *See* **Cheat.**

Oval, Ovate, *a.* अंडाकार, अंडाकृति. -*s.* अंडाकारः, अंडाकृति *f.*, कक्षा-क्षः.

Ovarious, *a.* अंडयुक्त, अंडरूप. -**Ovary**, *s.* अंडाशयः.

Ovation, *s.* लोक-संभावना-सत्कारः.

Oven, *s.* चुल्लि-ल्ली *f.*, कंदु *m. f.*, आपाकः. उखा.

Over, *prep.* उपरि (with gen.) or in comp., अधि-ऊर्ध्व in comp.; अधिक in comp.; 'o. 20' विंशत्यधिक; gen. ex. by अति, अधि, अभि, उत, सं, with verbs; 'cross o. a river' नदीपारं गम् 1 P. 2 (Superiority), प्र, अधि, वि in comp.; 'wander o.' परिभ्रम् 1, 4 P. पर्यट् 1 P; 'o. against' अभि-सं-मुखं, अभि-प्रति pr. -*adv.* परपारे, अन्यतीरे, पारं-रे 2 प्रति, सं, नि, with verbs; 'hand o. to another' अन्यस्मिन् निक्षिप् 6 P or संक्रम् c. 3 अधिकं, भूयः, अतिरिक्तं. 4 (Beyond) अति pr. 5 अव-,शिष्ट, उद्वृत्त, अंतरित (*a.*); अधिक in comp. 6 यावंतं, शेषं यावत्, ex. by पार; 'to read o.' अधि-इ 2 A, पारं गम् 7 अत्यंत, अति-सु-pr., अधिकं, अतिशय-एकांत in comp; as a prefix of verbs, ex. by अति, अत्यंतं. 8 अतीत, गत, अतिक्रांत, वृत्त, भूत; 'o. again' पुनरपि; 'o. and o. again' पुनःपुनः, मुहुर्मुहुः, वारंवारं; 'o. and above' अपरं च, अवशिष्ट-*a.*; 'to be o.' ex. by अवसित-अतीत-समाप्त-*a.*; *See* **Finish**; 'my work is o.' समाप्तकार्योऽस्मि; 'in a moment all will be o. with him' क्षणेन स समाप्तजीवितः-परासुः-भवेत्.

Overact, *v. t.* अतियत्नेन कृ 8 U, अत्याचर् 1 P.

Overawe, *v. t.* आकुलीकृ 8 U, भयेन उपहन् 2 P or अभिभू 1 P. -ed, *a.* संभ्रमाकुल, भयोपहत.

Overbalance, *v. t.* *See* **Outweigh.** -*s.* अति-अधिक-भारः.

Overbear, *v. t.* वशीकृ 8 U, दम् c. (दमयति); नि-पत् c., धृष् c. -ing, *a.* धृष्ट, उद्धत, दृप्त, अवलिप्त, गर्वित, उत्सिक्त; *See* **Haughty.** -ingly, *adv.* सावलेपं, सदर्पं, उद्धतं.

Overboard, *adv* नौपृष्ठात्, नौकाया बहिः मध्येसमुद्रं. अर्णवमध्ये.

Overburden, *v. t.* अतिभारं न्यस् 4 U, अतिभारेण पीड् 10 or अर्द् 1 P or c. -ed, *a.* अतिभाराक्रांत.

Overcast, *v. t.* (मेघैः) आ-वृ 5 U, प्र-आ-छद् 10. कलुषीकृ 8 U, तिमिरीकृ, साभ्र-*a* कृ. -*a.* मेघावृत, मेघाच्छन्न, तमोवृत, साभ्र, सतिमिर, घनावरुद्ध.

Over-cautious, *a.* अत्यवहित.

Overcharge, *v. t.* अतिमूल्यं अर्थ् 10 A. 2 **Overload**, q. v. -*s.* अतिमूल्यप्रार्थनं.

Overcloud, *v. t.* *See* **Overcast.**

Overcome, *v. t.* अतिक्रम् 1 U, 4 P, तॄ 1 P, पारं गम् 1 P आ-अधि-रुह् 1 P, अति-इ 2 P; अति-शी 2 A, अतिरिच् pass. 2 जि 1 P, पराजि (A), परा-अभि-भू 1 P, वशीकृ 8 U, दम् c. (दमयति). 3 प्रभू c., पर्याकृश् 6 P. (with fatigue &c.) आकुलीकृ, आक्रम्, खिद् c., अव-सद् c., better by (*a.*); 'o. by the force of truth' सत्यबलेनाभिभूत, भूतार्थवचनेन कुंठितमति or किंकर्तव्यतामूढ; 'I am o. by sleep caused by fatigue' अपह्रिये परिश्रमजनितया निद्रया (U. 1). -*a.* परा-,जित, दांत, वशीकृत &c. 2 अभिभूत, व्याकुल, पर्याकुल, आकुल, आर्त, आतुर, ग्रस्त, आक्रांत, आविष्ट, परिगत, gen. in comp

Overdo, *v. t* अतियत्नेन कृ 8 U. 2 अति-पच् 1 P. -**Overdone**, *a.* अतिपक्व. 2 अतिश्रांत, परिक्लांत.

Overdress, *v. t.* उज्ज्वलवेशं भृ c., उद्भटनेपथ्यं भृ 3 P

Overdue, *a.* अतिक्रांतकाल.

Overeat, *v. t.* अति-खाद् 1 P or अद् 2 P.

Over-estimate, *v. t.* अति-गण् 10 or मन् 4 P. -*s.* अतिगणना.

Overfatigue, *v. t.* अति-खिद् c. or श्रम c. -*s.* अतिखेदः, अतिश्रमः.

Overflood, Overflow, *v. t.* जलेन आ-सं-प्लु c., परिवह् c., उपरि स्रु c., उत्सिच् 6 P or c. -*v. i.* परिवह् 1 P; उत्सिच् pass., प्रवृध् 1 A, स्फाय् 1 A; gen. ex. by अति-, पूर्ण, उत्सिक्त, आ-सं-प्लुत, स्फीत-वृद्ध-जल, प्रचुर, उपचित, आढ्य, घन, अतिरिक्त, उद्रिक्त, वृद्ध, स्फीत; 'with an eye o.-ing with joy' आनंदपरिवाहिणा चक्षुषा (S. 4); 'a heart o.-ing with kindness' दयार्द्रं हृदयं; 'my curiosity first o.-ed' प्रथमं कुतूहलं सपरिवाहमासीत् (S. 2); 'her eyes o.-ed with tears' अश्रुपरिप्लुतेक्षणा सा, अश्रुजलेनाप्लुते नेत्रे. -*s.* पूरोत्पीडः, आप्लावः, उत्सेकः, जलवृद्धि *f.*, तोयाप्लावः, जलोत्सेकः. 2 उद्रेकः, अतिरेकः, वृद्धि *f.*, स्फीति *f.*, उपचयः, आधिक्यं, प्राचुर्यं. -**ing,** *a.* उत्सिक्त, अति-परि-पूर्ण, अति-,बहुल, प्रचुर, आ-सं-प्लुत, उपचित, उद्रिक्त, अतिरिक्त; 'o. with water' जलव्याप्त, आप्लुतोदक; 'o. the boundary' अतिवेल. -*s.*, *See* (*s.*); 'to fill to o.' आ-परि-प्लु c.

Overgrow, *v.* अतिरुह् 1 P, अतिवृध् 1 A, अत्यंतं वृध्.

Overhang, *v. t.* उपरि लंब् 1 A, अव-प्र-लंब्, बहिः लंब् or स्फुर् 1 P

Overhasty, *a.* अतिसाहसिन्, साहसपरायण.

Overhaul, *v. t.* पुनः पुनः परीक्ष् 1 A or निरूप् 10.

Overhead, *adv.* ऊर्ध्वं, उपरि, उपरिस्थाने; मस्तकोपरि, अधिशीर्षं; 'the sun being o.' नभोमध्यारूढे सवितरि, मध्याह्नकाले

Overhear, *v. t.* अलक्षितं-निभृतं श्रु 5 P, प्रच्छन्नं आकर्ण् 10.

Overjoy, *v. t.* प्रहृष् c., अत्यंतं आनंद् c. -*s.* प्रहर्षः, अत्यंतप्रमोदः. -**ed,** *a.* प्रहृष्ट, परममुदित, हर्षाकुल, आनंदपुलकित, उल्लसित, हृष्टचित्त.

Overlap, *v. t.* अतिव्याप् 5 P.

Overlarge, *a.* अतिविपुल, अतिमहत्.

Overland, *a.* स्थल in comp.; 'o. route' स्थलवर्त्म, (प्रतस्थे स्थलवर्त्मना R. iv. 60.)

Overlay, *v. t.* आ-,छद् 10, आ-वृ 5 U, पिधा 3 U, पि-नह् 4 P. 2 अतिभारेण पीड् 10.

Overleap, *v. t.* उत्-लंघ् 1 A, 10, उत्प्लु 1 A.

Over-lenient, *a.* एकांत-अति-मृदु.

Overlie, *v. t.* अतिभारेण पीड् 10, नि-पत् 1P

Overload, *v. t.* अतिपूर् 10, अतिभारं न्यस् 4 U or आवह् c. (रोपयति); अतिभारेण आक्रम् 1 U, 4 P or पीड् 10. -**ed,** *a.* अतिपूरित-पूर्ण, अतिभाराक्रांत. -**ing,** *s.* अतिभारारोपणं, अतिभारन्यासः.

Overlook, *v. t.* उपेक्ष् 1 A, न मन् 10 or दृश् 1 P, न आदृ 6 A, क्षम् 1 A, 4 P, अवमृश् 6 P, मृष् 6 P. 2 अवेक्ष्, अधि-ष्ठा 1 P, अध्यक्षः भू 1 P. 3 आ-अव-लोक् 1 A, 10; *See* **Command.**

Overmuch, *a.* अतिमात्र, अत्यंत, अत्यधिक, एकांत, अतिरिक्त, अति pr. -*s.* आधिक्यं, अतिबाहुल्यं, अतिरेकः. -*adv.* अत्यंतं, अतिमात्रं, अति-भृ pr.

Overnight, *adv.* अतीतरात्रौ, गतनिशायां.

Overpass, *v. t.* अतिचर् 1 P, अतिक्रम् 1 P.

Overpay, *v. t.* अधिकमूल्यं दा 3 U.

Overpeopled, *a.* अतिजनाकीर्ण.

Overplus, *s.* *See* **Surplus.**

Overpower, *v. t.* परा-अभि-भू 1 P, पराजि 1 A, आक्रम् 1 U, 4 P; *See* **Overcome.**

Overprize, Overrate, *v. t.* अधिकं मन् 4 A or c., अतिमूल्यं स्था c. (स्थापयति).

Overreach, *v. t.* प्र-लभ् c., वंच् 10, विप्र-लभ् 1 A. -**ing,** *s.* प्रतारणं-णा, वंचनं; *See* **Cheat.**

Override, *v. t.* अति-धाव् 1 P. 2 **Overrule,** q. v.

Overrule, *v. t.* अधः क्षिप् 6 P, निराकृ 8 U, अधरीकृ, प्रत्यादिश् 6 P; *See* **Reject.** 2 प्र-भू 1 P. ईश् 2 A (with gen.), अधिष्ठा 1 P, शास् 2 P, नियम् 1 P.

Overrun, *v. t.* उप-द्रु 1 A, आक्रम् 1 U, 4 P, उप-अभि-द्रु 1 P, व्याप् 5 P, आकृ 6 P; *See* **Harass, Oppress.**

Oversee, *v. t.* अवेक्ष् 1 A, अधि-ष्ठा 1 P. -**er,** *s.* अवेक्षकः, अधिष्ठातृ *m.*, अध्यक्षः, अधिकृतः, अधिकारिन् *m.*

Overset, *v. t.* वि-,पर्यस् 4 U, परिवृत् c.; अधरीकृ 8 U, निपत् c., अधः क्षिप् 6 P. -*v. i.* परिवृत् 1 A नि-पत् 1 P.

Overshadow, *v. t.* आ-,छद् 10, छायया आवृ 5 U.

Overshoot, *v. t.* लक्ष्यं अतिक्रम् 1 U, 4 P, लक्ष्यात् भ्रंश् 1 A, 4 P or च्यु 1 A.

Oversight, *s.* अनवेक्षा, प्रमादः, भ्रमः; भ्रांति *f.*, स्खलितं, दृष्टिदोषः.

Oversleep, *v. i.* अति-दीर्घं-स्वप् 2 P.

Overspread, *v. t.* आच्छद् 10, आ-वृ 5 U, आस्तृ 5 U, आस्तॄ 9 U, पूर् 10, आक्रम् 1 U, 4 P, आ-सं-कॄ 6 P, वि-अव-तन् 8 U, व्याप् 5 P. -*a.* आच्छन्न, आच्छादित, आवृत, आस्तीर्ण, आक्रांत, आकीर्ण, व्याप्त, पूरित, पूर्ण.

Overstate, *v. t.* अतिशयेन वच् 2 P; *See* **Exaggerate.**

Overstep, *v. t.* अतिक्रम् 1 U, 4 P, लंघ् 1 A, 10.

Overstock, *v. t.* अति-पूर् 10 or संगृह् 9 P or उपचयय् c., प्र-सं-चि 5 U. **—s.** अतिसंचयः-संग्रहः-संभारः.

Overstrain, *v. i.* अत्यंतं यत् 1 A or उद्यम् 1 A.

Overstrung, *a.* अत्यंतं, आतत

Overt, *a.* प्रकाश, स्फुट, व्यक्त, स्पष्ट, अगूढ, प्रकट, प्रत्यक्ष. **—ly.** *adv.* प्रकाशं, स्पष्टं, प्रत्यक्षं, प्रकटं. **—ness,** *s.* स्फुटता, व्यक्तता.

Overtake, *v. t.* आ-सद् c., (पूर्वप्रस्थितं वैनतेयमप्यासादयेयं V. 1), लंघ् 1 A, 10; आत्मोद्धतैरपि रजोभिरलंघनीयाः (S. 1); 'not to be o.-n' &c.; सं-,प्राप् 5 P, आक्रम् 1 U, 4 P, ग्रह् 9 U. **2** अभिभू 1 P, धृ 1 P, 10, ग्रस् 1 A; सहसा-अकस्मात् आपत् 1 P or आक्रम्; *See* **Attack, Overcome**; 'o. business' कार्यं समाप् c.

Overtask, Overtax, *v. t.* अतिभारं-अतिकरं न्यस् 4 U or निक्षिप् 6 P.

Overthrow, *v. t.* नश् c, वि-प्र-,° क्षि 1, 5 P, ध्वंस् c., प्र-वि-उत्°, उच्छिद् 7 P, अव-उत्-सद् c. **2** परिवृत् c., परि-विपरि-अस् 4 U, पराक्षिप् 6 P or c., अधोमुखीकृ 8 U, निपत् c. **3** जि 1 P, पराजि (A.), अभि-परा-भू 1 P, दम् c. (दमयति), वशीकृ 8 U, परास् 4 U, भंज् 7 P, पराहन् 2 P. **—s.** नाशः, ध्वंसः, प्र-वि°-,उच्छेदः, उत्सादः, क्षय. **2** घातः, भंगः, भेदः, परा-अभि-भवः, पराजयः,व्यसनं. **3** परिवर्तनं, पर्यासः, निपातनं.

Overtop, *v. t.* मूर्ध्नि-शिखरे-स्था 1 P, अतिशी 2 A, अभि-भू 1 P; *See* **Excel.**

Overture, *s.* प्रस्तावः, उपन्यासः, उपक्षेपः, निवेदनं, प्रार्थना, वचनं; 'secret o.' उपजापः. **2** प्रस्तावना, उपोद्घातः.

Overturn, *v. t.* परि-विपरि-अस् 4 U, परिवृत् c., निपत् c., अधोमुखीकृ 8 U, अधरोत्तरीकृ. **2 Overthrow,** q. v.

Overvalue, *v. t.* अधिकं मन् 4 A or c., बहु मन्, अधिकमूल्यं कृ 8 U or स्था c. (स्थापयति).

Overweening, *a.* अत्यभिमानिन्, अतिदृप्त, अत्यवलिप्त, अतिश्लाघिन्.

Overwhelm, *v. t.* अभि-भू 1 P, आकुलीकृ 8 U, ग्रस् 1 A,आक्रम् 1 U, 4 P; अव-सद् c. अव-सं-स्तृ 9 P or c., अव-नि-पत् c. निक्षिप् 7 P. **2** आ-वृ 5 U. आस्तृ-स्तृ 5, 9 U. आच्छद् 10, आकॄ 6 P. **3** नि-,मस्ज् c. (मज्जयति), प्लु c., अव-वि°-, द्रु c., आ-सं-परि-°. **—ed,** *a.* अभिभूत, ग्रस्त, आक्रांत, मग्न, आकीर्ण, उपप्लुत, उपद्रुत, आकुल; *See* **Overcome**; 'o. with grief' शोकसमाकुल; 'o. with a flood of tears' बाष्पपरिप्लुत.

Overwork, *v. t.* अधिकं कर्म कृ c., अत्यर्थं आयस् c. or खिद् c.; (oneself) अत्यर्थं परिश्रम् 4 P. **—**अत्यायासः, अतिक्लेशः-श्रमः.

Overwrought, *a.* अतिपरिष्कृत.

Overzeal, *s.* अत्यौत्सुक्यं, अत्युत्कंठा. **—ous,** *a.* अत्युत्सुक, अत्यासक्त, अतिव्यग्र.

Oviform, *a.* अंडाकृति, कोशाकार.

Oviparous, *a.* अंडज, द्विज, द्विजन्मन्, अंडोत्पन्न.

Ovum, *s. See* **Egg.**

Owe, *v. t.* धृ 10, (with dat. of creditor). **2** ऋणबद्ध-*a.* भू 1 P, अनुगृहीत-*a.* भू; oft. ex. by pot. pass. part.; 'you o. respect to your elders' गुरुजनस्त्वया पूज्यः. **—ing,** *a.* देय, दातव्य, शोधनीय, निस्तार्य. **2** जनित, जात, उद्भूत, प्रयुक्त, कारण-प्रभव-हेतु-in comp.; 'o. to' ex. by abl. or instr.; 'to whom is your deliverance o.' कस्त्वन्मुक्तिहेतुः-कारणं, केन त्वं मोचितः.

Owl, *s.* कौशिकः, उलूकः, पेचकः, दिवाभीतः, दिवांधः, घूकः, निशाटनः, वायसारातिः; 'o.-light' मंदप्रभा, ईषत्प्रकाशः.

Own, *a.* स्वीय, स्वकीय, आत्मीय, स्वक, निज, आत्मभूत; स्व, आत्मन् in gen. or in comp.; 'my o.' मदीय; so त्वदीय, तदीय, युष्मदीय, अस्मदीय; 'of one's o. accord' स्वयं, स्वेच्छया; 'to make one's o.' आत्मसात् कृ 8 U. **—v. t.** स्वीकृ, अंगीकृ, प्रति-पद् 4 A, अभ्युप-गम् 1 P or इ 2 P, ग्रह् 9 U, *See* **Acknowledge. 2** (To be master of) ex. by स्वामी, ईश्वरः, पतिः, अधिकारी, with gen. or by (*a.*); or by gen. alone; 'I o. much land' विपुलभूमेः स्वाम्यहं; 'who o. s this treasure' कोऽस्य वित्तस्य स्वामी-पतिः, कस्येदं वित्तं **3** स्वत्वं प्रति-पद् c. or ब्रू c., स्वीय-*a.* इति वद् 1 P; *See* **Claim. —ed,** *a.* स्वीकृत; स्वत्वविशिष्ट; 'o. by me' मत्स्वत्वविशिष्ट, मत्स्वामिक, मदधीन. **—er,** *s.* स्वामिन् *m.* ईश्वरः, पतिः, अधिकारिन् *m.* ईशः, प्रभुः; *See* **Lord. —ership,** *s.* स्वत्वं, स्वामित्वं, स्वाम्यं,प्रभुत्वं, अधिकारः. **—ing,** *s.* स्वीकारः, अभ्युपगमः.

Ox, *s.* वृषभः, वृषः, उक्षन् *m.*, बलीर्दः, वृषः, ऋषभः, अनडुह् *m.*, गौः, भद्रः, सौरभेयः; 'a herd of oxen' औक्षकं; 'a large o.' महोक्षः; 'an old o.' वृद्धोक्षः, जरद्गवः; 'head of a herd of oxen' आर्षभ्यः; 'an o. allowed to go at liberty' षंडः, गोपतिः, इट्चरः; 'his shoulder' वहः; 'the dewlap of an o.' सास्ना, गलकंबलः; 'who bears the yoke' धुर्यः, धुर्वोढा; 'who draws a

cart ' शाकटः, ' who draws a plough ' हालिकः, सैरिकः; ' who bears a burden ' धूर्वहः, धुर्यः, धुरीणः, धौरेयः, धुरंधरः.
Oxidize, *v. t.* जॄ c. **-Oxidation,** *s.* जारणं, आतंचनं.
Oyster, *s.* शुक्ति *f.*, शुक्तिका, शुक्तास्फोटः; ' o.-shell ' शुक्तिपुटं.

P

Pabulum, *s.* भोजनं, आहारः, पौष्टिकं. **-Pabular,** *a.* पौष्टिक (की *f.*).
Pace, *s.* पदं, चरणन्यासः, पदविक्षेपः-पातः-क्रमः, पादविक्षेपः-न्यासः, विक्रमः. **2** गति *f.*, गमनं, अयनं, चलनं, चारः. **3** गतिवेगः-क्रमः; ' a quick p. ' द्रुतपदं; ' at a rapid p. ' द्रुतगत्या. **4** (Of horses) धारा, गतिः; *See* under **Horse;** ' a horse with a good p. ' सुखायनः, सुखचारः; ' keep p. with ' सह गम् or चल् 1 P. **-v. i.** परि-अति-क्रम् 1 U, 4 P; क्रमेण क्रमेण गम्-व्रज्-चल् 1 P; ' p. up and down ' इतस्ततः चल् or भ्रम् 1, 4 P; ' p. ing to and fro ' इतस्ततः परिक्रम्य. **-ed,** *a.* गति in comp.; ' slow-p. ' मंदगति, मंदगामिन्.
Pachyderm, *s.* कठिनचर्मन्-*a.* पशुः. **-atous,** *a.* कठिनचर्मन्. **2** (*Fig.*) सहिष्णु, मंद.
Pacify, *v. t.* सां(शां)त्व् 10, शम् c. (शमयति), प्र-उप°-,प्र-मद् c., सं-परि-तुष् c., आराध् c. **-ied,** *a.* शांत,प्रसादित, शांतक्रोध; ' to be p. ' शम् 4 P, प्रसद् 1 P, तुष् 4 P, शमं इ-या 2 P. **-ier,** *s.* शमकः, सांत्वकः. **-ic,** *a.* शांत, प्रशमित, निरुद्वेग. **2** सांत्व-प्रशम-शील; सांत्वनकारिन्, साम in comp.; ' p. words ' सामवादः. **-ication,** *s.* शमः, शमनं, शांति *f.*, प्र-उप°-, सांत्वनं, सामन् *n.*, प्रसादनं. **2** संधानं, संधिकरणं. **-icatory,** *a.* शांतिद, शांतिकर (री *f.*), शमक, सामोपायक, साम in comp.

Pack, *s.* भारः, कूर्चः, भांडं, गुच्छः, पोटलिका, पटलं. **2** गणः, संघः,वर्गः, समूहः, वृंदं, संचयः; *See* **Multitude,** ' p. of hounds ' श्वगणः, कुक्कुरसंघः; ' a p. of persons ' मंडलं, जनसमूहः; ' p.-horse ' पृष्ठ्यः, स्थौरिन्; ' p.-saddle ' पर्याणं, पल्यानं; ' p.-thread ' शाणसूत्रं; ' p.-cloth ' वेष्टनं, पटः. **-v. t.** पटलीकृ 8 U, पुटीकृ, पुटयति (D.), सपिंड् 10, कूर्चीकृ; ' p. in a box ' समुद्गके क्षि-अस् 3 U or निक्षिप् c. **2** कुकार्यार्थं-उप संपूर्य-संमिल् c. or समाह् 1 P or एकीकृ or संयुज् 7 U, 10. **3** (Off) अप-निः-सृ c., सहसा अपगम् c. (गमयति) or प्र-स्था c. (स्थापयति). **-v. i.** पुटीभू 1 P, पिंडीभू, एकीभू. **2** सहसा अपगम् 1 P or प्र-स्था 1 A. **-age,** *s.* भांडं, कूर्चः, वस्त्रादिगुच्छः. **-Packet,** *s.* पोटलिका, लघुकूर्चः, लघुवेष्टनं; पत्रवेष्टनं. **2** पत्रवाहिनी नौः.
Pact, *s. See* **Contract.**
Pad, *s.* कूर्चः. **2** उपधानं, उपबर्हः. **3** सुखायनः, सुखचारः. **4** पादविकः. **5** मृदुवस्तु *n.*, तूलादिद्रव्यं. **-v. t.** मृदुवस्तुना आ-स्तृ 5 U or पूर् 7U, 10. **-v. i.** मंदं or शनैः-चल् or व्रज् 1 P.
Paddle, *s.* क्षेपणि-णी *f.*, नौदंडः; ' p.-box ' क्षेपण्याधारः; ' p.-wheel ' नौचालनी. **-v. t.** नौदंडेन प्रेर् c. or चल् c. or प्रणुद् 6 P or c. **-v. i.** क्षेपण्या जले चल् c. or आहन् 2 U or तड् 10. **2** जले क्रीड् 1 P.
Paddock, *s.* वाटः, वाटिका.
Paddy, *s.* धान्यं.
Padlock, *s.* तालकं.
Padrone, *s. See* **Patron.**
Pæan, *s.* जयशब्दः-ध्वनिः-घोषः.
Pagan, *s.* देवता-प्रतिमा-पूजकः. **-ism,** *s.* देवतार्चनं, प्रतिमापूजा-उपासना; *See* **Idolater,-try.**
Page, *s.* पृष्ठं, पत्रं. **2** चेटः, किंकरः, भृत्यः, पार्श्वानुचरः, परिचरः, बालानुचरः.
Pageant, *s.* आडंबरः, शोभा; चमत्कारः, कौतुकं. **-a.** Ex. by (*s.*). **-ry,** *s.* आडंबरः; *See* (*s.*).
Pagoda, *s. See* **Temple.**
Pail, *s.* भांडं, पात्रं, भाजनं.
Pain, *s.* दुःखं, वेदना, पीडा, व्यथा, आतंकः, रुज् *f.*, रुजा, अ(आ)र्ति *f.*, सं-परि-तापः, बाधा,यातना, क्लेशः,कष्टं, कृच्छ्रं, उद्वेगः, खेदः; ' bodily p. ' व्याधिः; ' mental p. ' आधिः, मनस्तापः, मनोव्यथा, चित्तोद्वेगः; ' causing p. ' पीडा-दुःख-कर (री *f.*); ' suffering p. ' दुःखभाक्, दुःखित; ' sharp p. ' शूलः-लं, तीव्रवेदना. **2** (Pains)परि-,श्रमः, प्र-, यत्नः, उद्योगः, व्यवसायः, उद्यमः, उत्साहः, आ-प्र-यासः, कष्टं, ' to take p. s' प्रयत् 1 A, उद्यम् 1 A, चेष्ट् 1 A, घट् 1 A, व्यव सो 4 P. **3** दंडः, साहसं. **-v. t.** पीड् 10, दु 5 P, व्यथ् c. (व्यथयति), तप् c , सं-परि-उप°-, बाध् 1 A, क्लिश् 9 P, अर्द् 1 P or c., दुःखयति (D.). **-ed,** *a.* पीडित,दून, दुःखित, व्यथित, तापित, सं-परि-तप्त, आर्त, दुःखार्त, दुःखातुर, सवेदन, कृच्छ्रगत, सव्यथ; ' to be p. ' व्यथ् 1 A, पीड्-क्लिश्-तप्-pass. **-ful,** *a.* सकष्ट, क-ष्टावह, दुःखद, सव्यथ, दुःखार्त; *See*

Painful. 2 दुःखद, कष्ट, पीडा-दुःख-कष्ट-व्यथा-कर (री *f.*), दुःसाधक, कष्ट or क्लेश-द or प्रद, बाधक, संतापक. 3 श्रम-कष्ट-साध्य, दुष्कर, कठिन. **-fully,** *adv.* सव्यथं, कष्टं, सदुःखं, सोद्वेगं. 2 सश्रमं, सायासं, कृच्छ्रेण, कष्टेन. **-less,** *a.* दुःख or व्यथा-हीन or रहित. **-Painstaking.** *a.* व्यवसायिन्, उद्यमिन्, उद्योगिन्. उद्यम-उत्साह-शील; *See* **Industrious.**

Paint, *v. t.* आ-लिख् 6 P, चित्र् 10. 2 रंज् c., वर्ण् 10, रंगेण लिप् 6 P, वर्णैः क्षुभ् c. 3 वर्ण्; *See* **Describe.** **-s.** रंजकः-कं; वर्णिका, रंगः, लेपः; 'p.-brush' वर्तिका, तूलिका, तूलि *f.*, वर्णतूली, ईषिका. **-ed,** *a.* चित्रित, वर्णित; (in a picture) चित्र-आलेख्य-गत, चित्रार्पित, आलिखित. **-er,** *s.* चित्रक(का)रः, रंगाजीवः, चित्रकृत्-लिख् *m.*, रंजकः, चित्रकः, आलेखकः, तौलिकः. **-ing,** *s.* (Art) चित्रकर्मन् *n.*, चित्र-क्रिया-विद्या. 2 आलेखनं, वर्णनं, रंजनं, चित्र-लेखनं. 3 आलेख्यं, चित्रं; 'drawn in a p.' आलेख्यगत; 'p. on the body' पत्ररेखा, पत्ररचना, पत्राङ्गुलि-ली *f.*

Pair, *s.* युगं, युगलं, युग्मं, द्वितयं, द्वयं, यमलं-कं, युतकं; द्वंद्वं, मिथुनं, दंपती in comp. (of animate beings only); 'a p. of swans' हंसदंपती; 'a married p.' भार्यापती, जायापती, दंपती, जंपती, स्त्रीपुरुषौ. **-v. t.** संयुज् 7 U, 10; oft. ex. by **Match,** q. v.; 'well-p. ed rivals' तुल्यप्रतिद्वंद्विनौ. **-v. i.** मैथुनं आचर् 1 P or कृ 8 U, स्त्रीपुरुषवत् संगम् 1 A.

Palace, *s* प्रासादः, हर्म्यं, सौधः-धं, राजकुलं, राज or नृप-गृहं-भवन-मंदिरं (House, q. v.) **-Palatial,** *a.* महत्, विशाल, राजयोग्य; 'p. building' महाभवनं

Palæontology, *s.* शिलाजातविद्या.

Palæstra, *s.* मल्लभूमि *f.*

Palanquin, *s.* नरयानं, शिबिका, चतुरस्र-यानं, याप्ययानं.

Palate, *s.* तालु *n.*, काकुदं; 'soft p.' शुंडिका, अलिजिह्वा. 2 रुचि *f.*, अभिरुचिः. **-able,** *a.* आस्वाद्य, सुरस, स्वादु, रुच्य, रुचिकर (री *f.*), सरस, रसिक. **-al,-ial,** *a.* तालव्य.

Palaver, *See* **Flatter,-y.**

Pale, *a.* पांडु, पांडुर, विवर्ण, गतवर्ण, नीरक्त, मंदच्छाय, गतश्रीक; 'he grew or turned p.' विवर्णभावं प्रपेदे, पांडुच्छायो बभूव. 2 मंदप्रभ, मंदद्युति-कांति, हततेजस्, निस्तेजस्, मलिन or म्लान-प्रभ or कांति. 3 (Of colours) श्वेत, ईषत्, आ, in comp. 'p. blue' आनील, श्वेतनील. **-s.** शलाका, शल्यं, शूलः-लं, शंकुः, स्थाणुः 2 वृति *f.*, आवरणं, वेष्टनं, वरणः. **-v. t.** (शंकुपंक्त्या) आ-परि-वृ 5 U or c., परिवेष्ट् 1 A or c., अवरुध् 7 U. **-ing,** *s.* शंकुपंक्ति *f.*, आवरणं. **-ish,** *a.* आपांडु, आपांडुर. **-ness,** *s.* पांडुता, वैवर्ण्यं, पांडुवर्णः-रागः. 2 तेजः-प्रभा-हानि *f.*, कांतिक्षयः; न्यूनप्रभा.

Palette, *s.* *See* '**Pallet.**'

Palfrey, *s.* लघुवाजिन् *m.*, क्षुद्रघोटकः.

Palindrome, *s.* मुरजबंधः.

Palingenesis, *s.* रूपांतरं, रूपपरिवृत्ति *f.*

Palisade, *s.* स्तंभ or शंकु-पंक्ति *f.* or वलयः-यं, अवरोधकं.

Pall, *s.* वासस् *n.*, प्रावारः, प्रच्छदपटः. 2 प्रेतपटः, प्रेतवासस् *n.*, शवाच्छादनं. **-v. t.** विरसीकृ 8 U, अरुचिं उत्पद् c. **-v. i.** विरसीभू 1 P.

Palladium, *s.* पुर-नगर-देवता, रक्षादेवता. 2 रक्षा-क्षणं.

Pallet, *s.* खट्वा, लघुतल्पः. 2 वर्ण-रंग-पत्रं.

Palliate, *v. t.* (दोषं) लघूकृ 8 U, प्र-उप-शम् c. (शमयति), लंघयति (D.), प्रमृज् 2 P, क्षल् 10, आच्छद् 10. **-ion,** *s.* प्र-उप-शमः-शांति *f.*, लघूकरणं, दोष or पाप-मार्जनं-क्षालनं-शमः. **-ive,** *a.* उपशमन (नी *f.*), शांतिप्रद, शमक. **-s.** पाप-दोष-शमनं. 2 उपशमनं, शूलघ्नं, क्लेशापहं.

Pallid, Pallor, *See* **Pale,-ness.**

Palm, *s.* तलः-लं, प्रहस्तः, प्रपाणिः, प्रतलः, चपेटः, चर्पटः, करतलः; 'the p. s joined' संहततलः, संतलः; 'the hollowed p.' प्रसृतः-तिः, चुलुकः; 'joining the p. s together' बद्धांजलि, कृतांजलि, अंजलि-पुटं कृत्वा. 2 (Tree) तालः, तृणद्रुमः, द्रुमेश्वरः; (the fruit) तालं; 'p. of victory' जयध्वजः-लक्षणं; 'p. of superiority' गुणाधिक्यपताका. **-v. t.** करतले गुप् 1 P or गुह् 1 U. 2 (Off) प्रतॄ c., वंच् 10; *See* **Cheat;** 'the trick was p. ed off upon him' तेन छद्मना असौ सम्यग् विप्रलब्धः. **-ate, -ated,** *a.* करतलाकृति. **-y,** *a* तालावृत, तालसंकीर्ण. 2 समृद्ध, श्रीमत्, विभव-भूति in comp.; 'p. days' विभवकालः, विभवः.

Palma-Christi, *s.* एरंडः, उरुबूकः, रुबू-(बु)कः, रुचकः, चित्रकः, चंचुः, पंचांगुलः, मंडः, वर्धमानः, व्यडंबकः.

Palmister, *s.* सामुद्रज्ञः, सामुद्रिकः **-Palmistry,** *s.* सामुद्रिकं, सामुद्रविद्या.

Palmiped, *a.* जालपाद (पदी *f.*).

Palmyra, *s.* *See* **Palm** (2).

Palpable, *a.* स्पर्शज्ञेय-गोचर, स्पृश्य. 2 स्थूल, घन, गाढ, निबिड. 3 स्पष्ट, सुविज्ञेय, प्रत्यक्ष, व्यक्त. **-Palpably,** *adv.* स्फुटं, व्यक्तं, प्रत्यक्षं.

Palpitate, *v. i.* वेप् 1 A, कंप् 1 A, स्पंद् 1 A, स्फुर् 6 P, उद्वेल् 2 P. **-ion,** *s.* स्पंदनं, कंपः, स्फुरणं, स्फुरितं, वेपनं, वेपथुः.

Palsy, *s.* स्तंभः, संधि-°, स्वापः, सुप्ति *f.* 2 पक्षाघातः, पक्षवायुः. -*v. t.* स्तंभ् 9 P or c., जडीकृ 8 U, स्वप् c., चैतन्यं भञ्ज् c. **-ied, -ical,** *a.* पक्षवायुग्रस्त.

Palter, *v.* *See* **Prevaricate.**

Paltry, *a.* क्षुद्र, लघु, तुच्छ, असार, अपकृष्ट, अधम, कु pr., कुत्सित.

Paludal, *a.* अनूप, जलमय

Pamper, *v. t.* (अत्यंतं) स्फाय् c. (स्फावयति), संवृध् c., आप्यै c., परि पुष् c., संतृप् c., पुष् 10. **-ed,** *a.* स्फीत, परिपुष्ट, हृष्टपुष्ट, आपीन, आप्यायित. **-er,** *s.* अतिपोषकः, आप्यायकः. **-ing,** *s.* स्फीति *f.*, परिपोषणं, आप्यायनं.

Pamphlet, *s.* पत्रिका, लघुपुस्तकं. **-eer,** *s.* पत्रिकाकारः, लघुपुस्तककृत् *m.*

Pan, *s.* भाजनं, पात्रं, भांडं, आधारः; 'frying p' अंबरीषं, भ्राष्ट्रः; *See* under **Fry**; 'p.-cake' भृष्टापूपः. 2 विश्वमूर्तिः.

Panacea, *s.* सर्वरोगघ्नं औषधं, त्रैलोक्यचिंतामणिः.

Pancratium, *s.* मल्लयुद्धं-क्रीडा. **-Pancratic,** *a.* मल्लक्रीडानिपुण.

Pandect, *s.* विद्यासंग्रहः. 2 स्मृतिसंहिता.

Pandemic, *a.* सर्वजनीन, सार्वलौकिक (की *f.*), सर्वसामान्य; 'p. disease' जनपदोद्ध्वंसः.

Pandemonium, *s.* रक्षःसभा, पिशाचसभा.

Pander,-er, *s.* नर्मसचिवः, विटः, सुरतदूतः, कुंडाशिन् *m.*, संचारकः. -*v. t.* सुरतकामान् सं-पद् c., लोपटत्वे प्रयुज् 7 A, 10. **-ing, -ism,** *s.* कौट्टिन्यं, विटकार्यं.

Pandiculation, *s.* *See* **Stretching.**

Pane, *s.* काचफलकः-शिला.

Panegyric, *s.* स्तुति *f.*, श्लाघा, प्रशंसा, स्तुतिवादः-पाठः, गुणवर्णनं-कीर्तनं. **-al,** *a.* स्तुतिमय (यी *f.*), प्रशंसात्मक. **-Panegyrize,** *v. t.* स्तु 2 U, श्लाघ् 1 A प्रशंस् 1 P; *See* **Praise.** **-Panegyrist,** *s.* संस्तावकः, वैतालिकः, वंदिन् *m.*, मागधः, स्तुतिपाठकः.

Panel, *s.* कपाटः-टं, अररः-री-रं, शाखा, भागः. 2 स्थेयगणः,-पत्रं.

Pang, *s.* वेदना, यातना, व्यथा, पीडा; (extreme) कारणा, अतिव्यथा; *See* **Pain.**

Panic, *s.* संत्रासः, सहसोद्वेगः, महासाध्वसं, विप्लवः, आकस्मिकभयं, त्रासः; 'p.-struck or -seized' संत्रस्त, भयविह्वल, विद्रावित; 'p. in an army' पिंजलः, समुत्पिंजः. 2 अणुः, प्रियंगुः.

Pannel, *s.* पर्याणं.

Pannier, *s.* कंडोलः, पिटः, पे(पि)टकः, करंडः.

Panoply, *s.* सर्वायुधं, सर्वांगकवचः. **-ed,** *a.* संवर्मित, कृतसन्नाह.

Panorama, *s.* विश्वदृश्यं.

Pant, *v. i.* वेप् 1 A, स्पंद् 1 A, कंप् 1 A, उद्-ध्मा 1 P, स्फुर् 6 P, उच्छ्वस् 2 P. 2 कृच्छ्रेण निश्वस्, दीर्घ-स्थूलस्थूलं-निश्वस्. 3 सोत्कंठं स्पृह् 10 or अभिलष् 1, 4 P; *See* **Long.** **-s., -ing,** *s.* कंपः, स्फुरणं; कृच्छ्रोच्छ्वासः, उच्छ्वासः, स्थूलस्थूलनिश्वासः.

Pantaloon, *s.* जंघावस्त्रं-परिधानं. 2 भंडः, विदूषकः, वैहासिकः.

Pantechnecon, *s.* उपस्कर-संग्रहः-पण्यशाला.

Pantheist, *s.* विश्वदेवतावादिन् *m.* **-Pantheism,** *s.* विश्वदेवतावादः, वैश्वदेवमतं. **-Pantheon,** *s.* विश्वदेवतागणः, विश्वदेवकुलं.

Panther, *s.* द्वीपिन् *m.*

Pantomime, *s.* मुग्धनर्तकः, केवलं अभिनेतृ *m.*, मूकाभिनेता. 2 मुग्धाभिनयः, लास्यं, निःशब्दलास्यं-हावः.

Pantry, *s.* अन्नकोष्ठः, भक्ष्यागारं.

Pap, *s.* चूचुकं, स्तनाग्रं. 2 स्तनः, कुचः. 3 मृदु खाद्यं.

Papa, *s.* तातः, पितृ *m.* *See* **Father.**

Paper *s.* पत्रं, पत्रकं; 'written p' लेखः, लिखितं, पत्रिका, लेख्यं. -*v. t.* पत्रेण आच्छद् 10 or आस्तृ 5 U.

Pappy, *a.* मज्जायुक्त, मृदु, कोमल.

Papulæ, *s.* वि-,स्फोटः, पिटि(ट)का.

Par, *s.* समता, तुल्यता, साम्यं, सम-तुल्य-भावः; 'at p.' सम, तुल्य. **-ity,** *s.* साम्यं, तुल्यत्वं.

Parable, *s.* उपमा, दृष्टांतः, निदर्शनं. **-Parabolic,** *a.* दृष्टांतरूप.

Parabola, *s.* अर्धवृत्तं.

Parachute, *s.* विमानात् अवतरणार्थं छत्रं.

Parade, *s.* आडंबरः, दंभः, बाह्यशोभा. 2 यात्रा, सैन्ययात्रा. 3 शस्त्राभ्यासः, अस्त्र-रण शिक्षा, युद्धाभ्यासः, व्यायामः, योग्या; 'p.-ground' व्यायामभूमि *f.* -*v. t.* सदंभं-साडंबरं-दृश् c. 2 सैनिकान् व्यायम् c. or शस्त्रव्यापारं शिक्ष् c. -*v. i.* सदंभं पर्यट् 1 P or भ्रम् 1, 4 P.

Paradigm, *s.* निदर्शनं, रूपनिदर्शनं; 'p. of verbs' धातुरूपादर्शः.

Paradise, *s.* वैकुंठं, स्वर्गः, स्वर्लोकः, सुखभवनं; *See* **Heaven.** 2 नंदनवनं. **-Paradisiacal,** *a.* स्वर्गीय, स्वर्ग्य.

Paradox, *s.* असत्याभासः, विरुद्धमतं. **-ical,** *a.* अनुक्ताभास, लोकविरुद्ध.

Paragon, *s.* प्रतिमा, उपमा, आदर्शः, प्रतिरूपं; *See* **Model.** 2 अनुपमं वस्तु.

Paragraph, *s.* परिच्छेदः, खंडः, भागः, वाक्यखंडः-विच्छेदः.

Parallax, *s.* लंबनं.

Parallel, *a.* समांतर. **2** सदृश (शी *f.*), समान, सम, तुल्य, संवादिन्, समरूप, अनुरूप. –*s.* समांतररेखा; 'p. of latitude' अक्षवृत्तं. **2** सादृश्यं, साम्यं, समता, आनुरूप्यं, उपमा, प्रतिमा, प्रतिरूपं; 'having no p.', 'un-p.ed' अनुपम, अद्वितीय; *See* **Matchless.** –*v. t.* समांतरीकृ 8 U. **2** उप-प्रति-मा 3 A, 2 P, तुल् 10. **3** समीभू 1 P, संवद् 1 P. **–ism,** *s.* समांतरं, सादृश्यं.

Parallelogram, *s.* समांतरचतुर्भुजः.

Parallelopiped, *s.* समांतरखातः.

Paralysis, *s.* स्तंभः, स्वापः, जाड्यं, सादः, पक्षाघातः; 'p. of limbs' अंगभंगः, गात्रोपघातः, गात्रसादः. **–Paralytic,** *a.* सुप्तत्वच्, स्तब्धगात्र, पक्षवायुग्रस्त. **–Paralyze,** *v. t.* संस्तंभ् 9 P, जडीकृ 8 U, अव-,सद् c., स्वप् c.; 'my limbs are p.-ed' सीदंति मम गात्राणि.

Paramount, *a.* प्रधानतम, सर्वाधीश, परम, विशिष्ट, प्रमुख, प्रधान; 'p. lord' अधीश्वरः, सम्राट्, सर्वेशः, सार्वभौमः; 'p. sway' साम्राज्यं.

Paramour, *s.* भुजंगः, जारः, विटः, उपपतिः. **2** (Female) उपपत्नी, उपस्त्री.

Parapet, *s.* वक्षोद्घ्नः प्राकारः.

Paraphernalia, *s.* सामग्री, परिच्छदः, उपकरणं; 'royal p.' छत्रचामरादि राजचिह्नं, राजलक्षणानि; 'woman's p.' स्त्रीधनं, यौतकं.

Paraphrase, *v. t.* विस्तरेण व्या-ख्या 2 P, अनुवद् 1 P, शब्दांतरेण विपरि-णम् c. (णमयति). –*s.* अनुवादः, मूलशब्दविस्तारः-विवरणं. **–Paraphrastic,** *a.* मूलाधिकशब्द, विस्ताररूप.

Parasite, *s.* पराचभोजिन् *m.*, पराचपुष्टः, परपिंडादः, पात्रेसमितः. **2** विटः, चाटुकारः; *See* **Flatterer. 3** वंदा, वृक्षादनी, वृक्षरुहा, जीवंतिका. **–ic,-ical,** *a.* पराचपुष्ट, पराश्रय, परोपजीविन्; वृक्ष or तरु-रोहिन् or रुह.

Parasol, *s.* छत्रं, आतपत्रं.

Parboil, *v. t.* ईषत् क्वथ् 1 P.

Parcel, *s.* पोटली, पोटलिका, कूर्चः, भांडं. **2** भागः, अंशः, खंडः, उद्धारः. **3** राशिः, चयः, संघः, गणः, समूहः, वृंदं; 'part and p.' अंगभूत *a.*, शरीरावयवभूत *a.*; 'she forms, as it were, part and p. of my body' अव्यतिरिक्तेयमस्मच्छरीरात् (Ks. 151); मेनकासंबंधेन शरीरभूता मे शकुंतला (S. 6). –*v. t.* (Out) विभज् 1 U, विभागशः विन्यस् 4 U or कृप् c.

Parcener, *s.* समांशिन् *m.*, समाधिकारिन् *m.* **–Parcenary,** *s.* समाधिकारः.

Parch, *v. t.* तप् c., दह् 1 P, प्लुष् 1 P, भ्रस्ज् 6 P; उत्-,शुष् c. (throat &c.). **–ed,** *a.* तप्त, दग्ध; भ्रष्ट, शुष्क, उच्छोषित, निर्जल, शोषितजल, क्षाम; 'having his throat p. up with thirst' पिपासाक्षामकंठः.

Parchment, *s.* चर्मपत्रः-पत्रं.

Pard, *s.* *See* '**Leopard.**'

Pardon, *v. t.* क्षम् 1 A, 4 P, सह् 1 A, मृष् 4 P, 10, मुच् 6 P, अव-सृज् 6 P, तिज् desid. (तितिक्षते). –*s.* क्षमा, क्षांति *f.*, तितिक्षा, मर्षणं, मोचनं, दोषमुक्ति *f.*, अपराधक्षमा; 'I beg your p.' क्षंतव्योऽहं भवता; 'to beg p. of' क्षमां प्रार्थ् 10 A. **–able,** *a.* क्षंतव्य, मर्षणीय, क्षमार्ह, सोढव्य, क्षमोचित. **–ed,** *a.* क्षांत, मर्षित, दोष-दंड-मुक्त, मुक्तदंड-दोष.

Pare, *v. t.* तनूकृ 8 U, अवकृत् 6 P, तक्ष् 1, 5 P, त्वक्ष् 1 P, अवच्छिद् 7 P, खंड् 10, उल्लिख् 6 P, वि-लू 9 U. **2** (Skin) निस्त्वचीकृ, निस्तुषीकृ, त्वचयति (D.), त्वचं निष्कृष् 1 P, 'having p. ed nails' कृत्तनखः. **–er,** *s.* तष्टृ *m.*, खंडकः. **–ing,** *s.* तक्षणं, कर्तनं, तनूकरणं. **2** तष्टं, खंडः, भिन्नं, विदलं, शकलः-लं.

Paregoric, *a.* शूलापह, शूलशामक.

Parent, *s.* मातृ *f.*, पितृ *m.*; *See* **Mother, Father;** 'p. s.' मातापितरौ, पितरौ, मातरपितरौ, प्रसूजनयितारौ; 'p. institution' उत्पादिका-पितृभूता-शाला; 'p. tree' उत्पादकः-जन्मदः-वृक्षः. **2** प्रभवः, कारणं, बीजं, हेतुः, उत्पादकः, जन्महेतुः. **–age,** *s.* अन्वयः, जाति *f.*, कुलं, वंशः, जन्मन् *n.*, उत्पत्ति *f.*; 'of royal p.' राजवंश्य, नृपबीज; 'of noble p.' महाकुल, कुलजन्मन्, अभिजनवत्. **–al,** *a.* पितृ, मातृ in comp., पैतृक (की *f.*), मातापितृयोग्य, पित्रुचित, पित्रनुरूप; 'p. affection' वात्सल्यं, अपत्यस्नेहः, पुत्रप्रीति *f.*

Parenthesis, *s.* निक्षेपचिह्नं; निक्षिप्तवाक्यं-वचनं, उप-अनन्वित-वाक्यं, प्रासंगिक-अप्रधान-वचनं. **–Parenthetical,** *a.* प्रासंगिक (की *f.*), निक्षिप्त, निवेशित, मूलानन्वित अप्रधान. **–ly,** *adv.* निक्षिप्य, मूलानन्वयेन.

Parergon, *s.* शेषपूरणं.

Parget, *s.* लेपः, सुधा.

Parhelion, *s.* सूर्याभासः, मिथ्यासूर्यः.

Pariah, *s.* अंत्यजः, हीनजातिः.

Parish, *s.* पौरोहित्यभूमि *f.*-प्रदेशः; 'p. priest' ग्रामयाजकः-पुरोहितः. **–Parishioner,** *s.* ग्रामिकः, ग्रामस्थः, ग्रामवासिन् *m.*

Park, *s.* उपवनं, कृत्रिमवनं; क्रीडा-प्रमद-वनं, आक्रीडः, मृगयास्थानं-भूमि *f.* **–er,** (P. keeper) *s.* वनपालः, उद्यानरक्षकः.

Parley, *v. i.* संभाष् 1 A, संवद् 1 P, संलप् 1 P. –*s.*, **–Parlance,** *s.* संभाषणं, संवादः, संकथा, संलापः. **2** संधिप्रसंगः.

Parliament, *s.* विचार-मंत्रण-सभा, प्रतिनिधि-सभा.

Parlour, *s.* आलाप-संकथा-स्थानं, सलापकोष्ठः.

Parlous, *a.* भयावह, भयंकर, भीतिमद्.

Parochial, *a.* ग्राम्य, ग्रामीय, ग्रामिक (की *f.*).

Parody, *s.* अनुकरणकाव्यं. —*v. t.* शब्दान् परिहृत् c.

Parole, *s.* उक्ति *f.*, वचनं, प्रतिज्ञा.

Paronomasia, *s.* श्लेषः.

Paronychia, *s.* चिप्पं.

Parotis, *s.* लालाधारः.

Paroxysm, *s.* वेगः, सं-आ-वेगः, आवेशः, आक्रमः; 'p. of rage' क्रोधावेशः; 'in a p. of rage' क्रोधावेशवशात्.

Parricide, *s.* पितृ-हत्या-वधः-घातः. 2 पितृहन् *m.*, पितृघातिन् *m.*, पितृघ्नः. **-al,** *a.* पितृहन्. 2 पितृवधात्मक.

Parrot, *s.* शुकः, कीरः, किंकिरातः, वक्रतुंडः-चंचुः.

Parry, *v. t.* नि-वृ c., परिहृ 1 P, प्रतिहन् 2 P.

Parse, *v. t.* (पदानि) भंज् 7 P, छिद् 7 P. **-ing,** *s.* पदभंजनं-छेदः.

Parsimony, *s.* अल्प-मित-व्ययः. **-ious,** *a.* अल्प-मित-व्ययिन्, कृपण, व्ययपराङ्मुख (खी *f.*), दृढबद्ध-मुष्टि. **-iously,** *adv.* कार्पण्येन, मितव्ययेन. **-iousness,** *s. See* (*s.*).

Parsley, *s.* अजमोदा.

Parson, *s.* ग्रामपुरोहितः, ग्रामोपाध्यायः, ग्रामगुरुः. **-age,** *s.* ग्रामगुरुगृहं.

Part, *s.* वि-,भागः, अंशः, खंडः-डं, शकलः-लं, लवः, वि- दलं, भित्तं, कला. 2 प्र-,देशः, एकदेशः, अवयवः, अंगं. 3 (Allotted) वि-, भागः, अंशः, उद्धारः, वंटः. 4 कर्मन् *n.*, कार्यं, नियोगः, धर्मः, स्वकर्तव्य-धर्मः; 'perform one's p.' कर्म निर्वह् c., नियोगमनुष्ठा 1 P. 5 भूमिका; पात्रं; 'assignment of p.s' भूमिकाकल्पनं. 6 अंगं, अवयवः, घटकः, घटकावयवः; 'consisting of 4 p. s' चतुरंगं (बलं). 7 वारः, पर्यायः; *See* **Turn. 8** पक्षः. 9 संबंधः, अनुषंगः; 'to have a p. in' संबंध्-अनुषंज्-pass. 10 (P.-s) मति *f.*, मतिगुणः. बुद्धि *f.*, धीशक्ति *f.*, *See* **Intellect**; (region) प्र-,देशः; 'for (on) one's p.' तावत्, अपि; 'for the most p.' प्रायः, बहुशः, प्रायशः, प्रायेण, भूयिष्ठं; *See* **Mostly,** 'by p.s,' 'in p.s' भागशः, अंशशः; 'in p.' अंशतः, ईषत्, किंचित्; 'in good p.' संप्रीतमनसा, प्रियं, अनुकूलं, प्रसन्नं; प्रसन्नमनसा; 'in ill p.' रुष्ट-खिन्न-मनसा; 'in four p.s' चतुर्धा; 'in many p.s' बहुधा. —*v. t.* विभज् 1 U, परि-कल्प् c., विभागशः विन्यस् 4 U, वंट् 10; *See* **Divide.** 2 वि-युज् 7 A, 10, विश्लिष् c., पृथक् कृ 8 U, वि-भिद् 7 P or c., विच्छिद् 7 P; (the hair) सीमंतयति (D.). —*v. i.* वियुज्-विभिद्-विच्छिद्-pass., वियुज् 1 P, विश्लिष् 4 P, अप-या 2 P, अपगम्. 3 वि-, दल् 1 P, स्फुट् 6 P, वि-दृ pass., शकलीभू. 4 (With) आ-मंत्र् 10 A, आपृच्छ् 6 A; त्यज् 1 P, क्षिप् 6 P (place); 'let me now p. with you' अनुजानीहि मामधुना गमनाय. **-ing,** *a.* प्रास्थानिक (की *f.*), प्रस्थान-प्रयाण in comp.; 'p. ceremony' प्रस्थानकौतुकं. —*s.* वियोगः, विश्लेषः, विरहः, विभेदः. 2 वि-अप-गमः, प्रस्थानं, प्रयाणं, अपयानं; 'p. of the hair' सीमंतः, सीमंतरचनं. **-ly,** *adv.* अंशतः, भागतः, किंचित्, ईषत्, स्तोकं, कियत्, अल्पं, स्तोकांशेन, खंडतः. **-Partake,** *v.* अंशभाज्-*a.* भू 1 P, अंश-भागं-ग्रह् 9 U or हृ 1 P, भज् 1 A, अंशे भज्, भागिन्-*a.* भू; *See* **Share.** 2 भुज् 7 A, सेव् 1 A. **-er,** *s.* अंशिन् *m.*, भागी, अंश-भाग-ग्राही-हारी-हरः, सह-भाक्-भोगिन्, भुज्-भाज्-in comp. **-Partial,** *a.* अव्यापक, असार्वत्रिक-आंशिक (की *f.*), असमग्र, असंपूर्ण, असकल, एकदेश-खंड- in comp.: 'p. eclipse' खंडग्रासः; 'p. rent' एकदेशच्छिद्रं. 2 पक्षपातिन्, पक्षस्नेहिन्, पक्षानुकूल, पक्षानुरागिन्, एकदेशीय, सपक्षपात, संगिन्, असमदृष्टि, असमदर्शिन्. **-ity,** *s.* पक्षपातः, पक्षपातिता, पक्षस्नेहः-आनुकूल्यं-अनुरागः, असमता, असमदृष्टि *f.*-बुद्धि *f.*, संगः. 2 स्नेहः, अनुरागः, प्रणयः, प्रेमन् *m. n.*; 'speak without any p.' मध्यस्थतां गृहीत्वा भण (M. 3). **-ly,** *adv.* अंशतः, असमग्रं, असकलं, असंपूर्णं, क्वचित् क्वचित्, असर्वत्र, खंडतः, एकदेशे, ईषत्, स्तोकं, खंड-एकदेश-in comp.; 'p. broken' खंडभग्न; *See* **Partly. -Participate,** *v. t.* भाग-अंशं-ग्रह् 9 U, संविभज् 1 U. **-ion,** *s.* अंश-भाग-ग्रहणं, संविभागः, सहभोगः-भुक्ति *f.* **-Participant,** *a., s.* भागिन्, अंशिन्; *See* **Partaker. -Particle,** *s.* कणः, अणुः, लवः, क्षुद्रांशः, कणिका, लेशः, कला, परमाणुः. 2 निपातः, अव्ययः-यं. **-Partition,** *s.* परिच्छेदः, वियोजनं. 2 वि-,भागः, विभागकल्पना, विभजनं, वंटनं, वर्णनं. 3 व्यवच्छेदनं, भित्ति *f.*, व्यवधा-धानं, कोष्ठः, संधिः. —*v. t.* विच्छिद् 7 P, विभज् 1 U, अंशांशि कृ 3 U; *See* (*v. t.*). **-Partner,** *s.* अंशिन् *m.*, भागी, समांशी, सहभोगी-भागी; संगी, सहायः, सहकारी, संभूयकारी, संसर्गी, अनुषंगी; 'p. of joys and sorrows' समदुःखसुखः (S.3). 2 **Husband, Wife,** q.v. **-ship,** *s.* सहकारिता, संभूयकारित्वं, समांशिता, संभूयसमुत्थानं.

Parterre, *s.* पुष्पवाटी-टिका, कुसुमाकरः.

Participle, *s.* कृदंतः; 'present p.' शतृ, शानच्; 'past p.' निष्ठा; 'potential pas-

sive p.' कृत्वः (all being names of terminations).

Parti(y)coloured, *a. See* under **Party.**

Particular, *a.* विशिष्ट, सविशेष, विशेषक, अव-परि-च्छेदक, विशेष in comp. 2 व्यक्त, विभिन्न, विविक्त, उद्दिष्ट, पृथगात्मक, अमुक in comp. 3 अव्यापक, अनौत्सर्गिक (की *f.*); विशिष्ट, not General q. v. 4 असाधारण (णी *f.*), असामान्य, लोकोत्तर, अप्राकृत (ती *f.*). 5 विलक्षण, अपूर्व. 6 सूक्ष्म, सूक्ष्मदृष्टि, सूक्ष्मदर्शिन्, 'at a p. time' विशिष्टसमये, समयविशेषे; 'a p. rule' विशेषविधिः; 'he is very p. about his dress' वेषक्रियायां सोऽतीव सूक्ष्मदृष्टिः. -*s.* विशेषः, अव-परि-च्छेदः; 'give p.s of the man' तस्य नरस्य विशेषं ब्रूहि; 'he told all the p.s of the battle' युद्धं स विस्तरेण अवर्णयत्, अखिलं युद्धवृत्तांतं अकथयत्; 'in p.' विशेषतः, विशेषेण. **-ity,** *s.* विशेषनिर्देशः कथनं, एकैकशःनिर्देशः. 2 असामान्यता, अव्यापकत्वं. 3 पार्थक्यं, भिन्नता, व्यक्ति *f.*, विशिष्टता. 4 विवरणं, विस्तरः. **-ly,** *adv.* विशेषतः, सविशेषं, प्रधानतः. 2 विस्तरेण, सविस्तरं; सूक्ष्मतया, अतिसूक्ष्मं. 3 पृथक्, अवयवशः, एकैकशः. **-Particularize,** *v. t.* विशिष् 7 P, एकैकशः निर्दिश् 6 P or अभि-धा 3 U, सविशेषं वर्ण् 10 or कथ् 10, व्यवच्छिद् 7 P. **-ation,** *s.* विशेषवर्णनं-ना, विशेष-निर्देशः-कथनं, व्यवच्छेदः. **-ed,** *a.* विशेषित, एकैकशः निर्दिष्ट, व्यवच्छिन्न.

Partridge, *s.* तित्तिरः-रिः, चकोरः-रकः.

Parturient, *a.* आसन्नप्रसवा, प्राप्तप्रसववेदना **-Parturition,** *s.* प्रसवः, जननं, जन्मन् *n.* उत्पत्ति *f.*

Party, *s.* पक्षः; 'one's own p.' स्व-आत्म-पक्षः; 'of one's p.' स्वपक्षावलंबिन्, स्वपक्षपातिन्; 'of the opposite p.' वि-प्रति-पक्षः. 2 संसर्गः, सपक्षाणां गणः-संघः, कृतसंसर्गा जनाः, शाखा, पक्षः. 3 गणः, समूहः, दलं, संघः, वृंदं, मंडलं, गुल्मः-ल्मं, पंक्ति *f.* 4 अर्थिन् *m.*, प्रत्यर्थी, वादी, प्रतिवादी. 5 सभा, समाजः, पंक्तिः, गणः; 'dinner (convivial) p.' सग्धि *f.*, सह-सं-भोजनं; सपीति *f.*, तुल्यपानं (drinking p.). 6 विशिष्टजनः, व्यक्ति *f.*, विवक्षितपुरुषः. 7 संबंधिन् *m.*, अनुषंगी, भागी, अंशी, सहकारी, सहायः; 'a p. to a plot' कूटसहायः. -*a.* पाक्षिक (की *f.*), पक्ष in comp. by (*s.*); 'p.-coloured' चित्रविचित्र, नानावर्ण-रंग, विचित्र; 'p.-man' पक्षपातिन् *m.* पाक्षिकः; 'p.-spirit' पक्षपातः; *See* **Partiality;** 'p.-wall' भित्ति *f.*, संधिः; कुड्यं. **-Partisan,** *s.* पक्षपाती, पक्षावलंबी, पक्ष्यः, एकपक्षः, सपक्षः, सहोत्थायी, अनु-,संगी, पार्श्व(र्श्वि)कः, पक्षधरः. **-ship,** *s.* पक्षपातः-ग्रहणं-अवलंबनं.

Parvenu, *s. See* **Upstart.**

Pasquinade, *s.* निंदात्मको लेखः, उपहासलेखः.

Pass, *v. t.* अति-व्यति-इ 2 P, अतिक्रम् 1 U, 4 P; 'they two p. ed each other' परस्परमतीत्य-उल्लंघ्य-गौ निर्गतौ; तॄ 1 P, सं-उत्-निः-°, उत्-,लंघ् 1 A, 10, पारं गम् 1 P, अतिगम्; 'p.ed his examination' परीक्षापारं गतः, परीक्षामुत्ततार. 2 (Time) गम् c. (गमयति), नी 1 P, अति-वह् c., क्षै c. (क्षपयति), या c. (यापयति); 'he with difficulty p. ed eight years' तेनाष्टौ परिगमिताः समाः कथंचित् (R. VIII. 92); 'p.ing (staying for) three nights' तिस्रो वसतीरुषित्वा (R. VII. 33). 3 सं-,चर्-ल् c., संक्रम् c. 4 निष्पद् c., व्यव-स्था c. (स्थापयति), सिध् c. (साधयति); सं-अनु-मन् 4 A, परिग्रह् 9 P (bill &c.): 'p. sentence' निर्णयं दा 3 U, दंडं आदिश् 6 P; 'this p. es conception' विचारविषयातिक्रांतमेतत्, धियः पथि न वर्तते. -*v. i.* गम्, इ-या- 2 P, चल्-चर् 1 P, प्र-,सृ 1 P, अति-व्यति-इ, अतिक्रम्; 'let it p. now' तिष्ठतु तदधुना, यातु, किमनेन. 2 प्र-चल्-र्, प्रचलित-*a.* भू 1 P, प्र-सृ, प्रचलीभू. 3 सिध् 4 P, निष्पन्नी-सिद्धीभू, अनु-सं-मन् pass., परिग्रह् pass. 4 उप-,संक्रम्, संचर्. 5 संवृत् 1 A, समा-पद् 4 A, सं-,भू, आ-पत् 1 P, घट् 1 A; *See* **Happen; Occur. -away,** अति-व्यति-इ, गम्, या, अतिक्रम्, अतिवृत. 2 प्र-,नश् 4 P, प्र-वि-ली 4 A, तिरोभू, क्षि pass., क्षर् 1 P. **-by,** अतिक्रम्, अति-इ, अतिचर्, उल्लंघ्. 2 उपेक्ष् 1 A, न गण् 10, त्यज् 1 P, अपास् 4 U; *See* **Neglect. -for,** Ex. by denominatives: एरंडोपि द्रुमायते 'p. es for a tree'; मन्-गण्-pass.; 'he p.s for a learned man' पंडित इति मन्यते (जनैः). **-into,** निविश्-प्रविश्- 6 P. **-off,** अप-इ, अप-या-गम्, विगम्. -(*v. t.*) वि-भू c., संदृश् c., आकल् 10; 'tried to p. the matter off with a joke' तं वृत्तांतं परिहासमिव गणयितुं-आकलयितुं-यते; हृदयवल्लभोऽभिलिख्य कामदेवव्यपदेशेन सखीपुरतोऽपह्नुतः (Rat. 2) 'p. ed off the picture of her beloved upon her friend as that of Cupid.' **-on,** प्र-वृत्, प्र-या-गम्-सृ. **-over,** उपेक्ष्, उत्सृज् 6 P, त्यज्, न गण्, लंघ्, अति-इ-अतिक्रम्, अतिक्रम्य गम्, तॄ; *See* (*v.t.*); अंतरयानि (D.), मध्यमांशावृत्तांतोऽन्तरित आर्येण (U. 1) 'is p.ed over' &c.; oft. by स्था, आस् 2 A with तावत्; 'let us p. over this sad tale' तिष्ठतु-आस्तां-तावदयं

दुःखवृत्तांतः. **-through,** निर्भिद् 7 P, प्रविश्य निर्भिद्; (thoughts &c.) *See* **Occur.** *-s.* संकटं, संक्रमः, संचरः, संकट or संबाध-पथः or मार्गः, दुर्गसंचरः, 2 दरी, विवरः, रंध्रं. 3 (Passport) अनुज्ञा, अनुमति *f.*, अनुज्ञापत्रं, मुद्रा; 'why do you leave the camp without (taking) a p.' किमर्थमगृहीतमुद्रः कटकान्निष्क्रामसि; 'without a p.' अमुद्रालांछितः (Mu. 2). 4 प्रहारः, आघातः, ताडनं. 5 दशा, अवस्था, स्थिति *f.*, दुर्दशा, दुर्गति *f.*, कष्टं, कृच्छ्रं, कष्टावस्था. **-able,** *a.* गम्य, तार्य, सुगम, उल्लंघ्य; 'not p.' दुर्गम, अगम्य. 2 सह्य, सोढव्य, उपेक्षणीय, विगुण. **-age,** *s.* गमनं, तरणं, यानं; 'p. through the world' लोकयात्रा, संसारपथः, 'p. to and fro' गमनागमनं, यातायातं. 2 मार्गः; *See* **Way.** 3 संक्रमः, संचारः, अतिक्रमः, पारगमनं, उल्लंघनं; *See* (*s.*). 4 गमन-संक्रमण-कालः. 5 संचरः, संक्रमः, दुर्गसंचरः. 6 गमनाधिकारः, अनुज्ञा- पत्रं- मुद्रा; *See* **Pass.** 7 वचनं, स्थानं, स्थलं, देशः. 8 वृत्तं, भूतं, वृत्तांतः; 'p.-money' आता(त)रः, तरमूल्यं-पण्यं, तारिकं, तार्यं. **-ed,** *a.* अतीत, गत, संक्रांत, व्यतीत, तीर्ण, सिद्ध. 2 (As excrement) उच्चारित, हन्न, गून. **-er,** *s.* (p.-by), पथिकः, अध्वगः, पांथः; *See* **Traveller.** **-ing,** *s.* तरणं, गमनं, चलनं. *-a.* गामिन्, यायिन् in comp. 2 अतिक्रामक. 3 उत्तम, परम, श्रेष्ठ, विशिष्ट. *-adv.* अतीव, अतिमात्रं, नितांतं, अति pr., अतिशय in comp. **-Passenger,** *s.* तरः, तरितृ *m.*, उत्तरणकृत्. 2 नौ or पोत-गामी or यायी. 3 पथिकः, यात्रिकः, पांथः; *See* **Traveller.** **-Past,** *a.* गत, अतीत, भूत, व्यतीत, अतिक्रांत, वृत्त, परोक्ष; 'p. time' भूतकालः. 2 पूर्व, पूर्वतन (नी *f.*); 'in p. times' पुरा, पूर्वं, पुराकल्पे. 3 सिद्ध, निष्पन्न, समाप्त, कृत *-s.* भूतं, अतीतं, समतीतं, अतिक्रांतं, गत-अतीत-भूत-कालः. *-prep.*, अति pr., अतीत, अतिक्रांत, नष्ट, हीन in comp., अ-निर्-pr.; 'p. cure' असाध्य, निष्प्रतीकार; 'p. the range of sight' चक्षुर्विषयातिक्रांत, नयनपथातीत; 'p. all shame' निर्लज्ज, नष्ट-त्यक्त-लज्ज; 'p. human strength' अतिमानुषशक्ति; *See* **Beyond** also.

Passible, *a.* वेदनक्षम.

Passion, *s.* भावः, विकारः, विकृति *f.*, वृत्ति *f.*, रागः, रसः, मनो-विकारः-धर्मः-भावः-वृत्तिः-रागः, इंद्रियवृत्तिः. 2 इंद्रियं; 'the p.s' इंद्रियाणि, इंद्रियवर्गः, 'subduing the p.s' इंद्रियनिग्रहः; 'p. of love' कामविकारः, शृंगारभावः; 'void of p.s' वीतराग, विरक्त; 'absence of p.s' विरागः, विरक्ति *f.* 3 प्रकोपः, संरंभः, क्रोधः, रोषः, अमर्षः, उत्-सं-तापः; चंडता, उग्रता, क्षोभः, व्या-सं-क्षोभः, चित्त-क्षोभः-तापः-वेगः. 4 लालसा, लोभः, लोलुपता, औत्सुक्यं, उत्कंठा, उत्कटेच्छा, गाढाभिलाषः, स्पृहा, आसक्ति *f.*; 'quality of (tendency to) p.' रजोगुणः, रजस् *n.* 5 कामः, मदनः, स्मरः, कामविकारः, स्मरमोहः, रजः, रजोवृत्तिः, मदः, कामुकत्वं, अभिलाषः, अनुरागः; *See* **Love, Lust.** 6 दुःखानुभवः, दुःखभोगः. 7 सहनं, कर्माश्रयता, ग्रहणं **-ate,** *a.* क्रोधन, कोपन, क्रोधिल, शीघ्रकोपिन्, सुलभकोप, संरंभिन् ससंरंभ, रोष-कोप-क्रोध-शील, अमर्षण, रोषण, क्रोधिष्ठ, चंड पित्त-स्वभाव, आवेशवत्, चंड उत्ताप-संताप-शील, तिग्म, उष्ण. 2 तीव्र, तीक्ष्ण, उग्र, अत्युत्कट, उच्चंड, प्रखर, अतिरिक्त, परम, नितांत, गाढ, उत्कट; 'p. love for gambling' द्यूते गाढाभिनिवेशः, 'p. lover of music' नितांतं संगीतप्रियः. 3 रागयुक्त, विकाराधीन, सराग, रागान्वित, उत्कंठित, सानुराग, रजोगुणिन्, कामार्त; 'a p. woman' भामिनी, कोपना. **-ately,** *adv.* सकोपं, सक्रोधं, ससंरंभं, सामर्षं. 2 चंडं, अत्युत्कटं, तीक्ष्णं, बलवत्. 3 सरागं, सानुरागं, रागपूर्वं. **-ateness,** *s.* चंडस्वभावः, सुलभकोपित्वं, रोषणता, &c. **-less,** *a.* विरक्त, रागहीन, शांत-वीत-राग, निःसंग.

Passive, *a.* कर्मवाच्यं (p. voice); 'impersonal p.' भाववाच्यं. 2 सहन, सहिष्णु, सहनशील-वृत्ति-धर्मक, तितिक्षु, अनिवारक; oft. ex. by सह् 1 A. 3 निश्चेष्ट, निष्क्रिय, अप्रवर्तक, कर्माश्रय, कर्मपात्र. **-ly,** *adv.* सहिष्णुतया, निश्चेष्टं, अप्रतिकारेण. **-ness,** *s.* सहनशीलं-धर्मः-वृत्तिः, सहिष्णुता. 2 निश्चेष्टता, कर्माश्रयता, कर्मपात्रता.

Passport, *s.* *See* **Pass,** *s.* 3.

Paste, *v. t.* (उदपेषं) वि-, लिप् 6 P, बंध् 9 P, आसज् c. *-s.* उदपेषः, जलपेषः; 'p.-board' संसृष्टपत्रं.

Pastern, *s.* अश्वखुरसंधिः.

Pastime, *s.* क्रीडा, विनोदः, लीला, केलि *f.*, विहारः, खेला, खेलनं, विलासः, कौतुकं.

Pastor, *s.* अवि-अजा-पालः, मेषपालः. 2 आचार्यः, गुरुः, उपाध्यायः. **-al,** *a.* Ex. by (*s.*) in comp.; 'p. life' अविपालवृत्ति *f.*; 'p. duties' धर्मकार्याणि; 'p. office' आचार्यकर्म. *-s.* 'p. poem' गोपकाव्यं.

Pastry, *s.* मिष्टान्नं, आपूपिकं, पिष्टकाः (pl.); 'p. cook' आपूपिकः, भक्ष्यंकारः.

Pasture, *s.* शाद्वलं, शाद्वल-तृणावृत-भूमि *f.*, यवसक्षेत्रं, गोप्रचारः. 2 तृणं, यवसं, घासः, पशव्यं, गवादनं, पशुभोजनं. *-v. i.* चर् 1 P, तृणं खाद् 1 P or भक्ष् 10. *-v. t.* चर् c., तृणं भुज् c. or खाद् c. **-age,** *s.* प्रचारभूमिः, गोप्रचारः. 2 शस्यं, घासः, यवसं, *See* (*s.*)

Pasty, *s.* मांसपूपः.

Pat, *a.* युक्त, उचित. -*adv.* युक्तं, उचितं, सम्यक्. -*v. t.* हस्तेन स्पृश् 6 P or परामृश् 6 P; लघु प्र-हृ 1 P or तड् 10. -*s.* लघ्वाघातः, लघुप्रहारः.

Patch, *v.* सं-ग्रंथ् 9 P, वस्त्रखंडान् निषिव् 4 P or सं-धा 3 U; 'p.ed up garment' नानाखंडैर्ग्रथितं वस्त्रं, कर्पटः, कंथा; 'wearing p. ed garment' कंथाधारिन्, कर्पटिक. -*s.* खंडः-डं, शकलः-लं, वस्त्र-पट-खंडः, ग्रथितखंडः, 'p.-work' संग्रंथनं, खंड-कर्मन् *n.* कंथाकरणं. 2 भूभागः, प्रदेशः, भूमि *f.*, क्षेत्रं. -**ed,** *a.* संग्रथित, खंडमय (यी *f.*), खंडरूप.

Pate, *s.* मुंडं, मस्तकाग्रं; *See* **Head.**

Patent, *a.* स्पष्ट, व्यक्त, स्फुट, सुप्रकाश, सुव्यक्त, सुस्पष्ट, प्रत्यक्ष. -*s.* असामान्याधिकारः, विशिष्टाधिकारपत्रं. -**ee,** *s.* असामान्याधिकारिन् *m.*

Pater-familias, *s.* कुलपतिः, कौटुंबिकः.

Paternal, *a.* पैतृक (की *f.*), पैत्र (त्री *f.*), पित्र्य, पितृ in comp., पित्रागत, पितृप्राप्त. 'p. estate' पैतृकी भूमिः; 'p. aunt' पितृष्वसा. 2 पित्रनुरूप, पितृतुल्य-सन्निभ. -**ly,** *adv.* पितृवत्, पितेव, पितृसंनिभं.

Paternity, *s.* पितृत्वं, पितृधर्मः. 2 प्रभवः, प्रसूति *f.*

Path, *s.* (P.-way) पथिन् *m.*, मार्गः, पद्धति *f.*, सरणि-णी *f.*, वर्त्मन् *n.*, पदवि-वी *f.*; *See* **Way;** 'the p. of a planet' कक्षा-क्षः; 'the wrong p.' उत्पथः, कापथः, विमार्गः; 'good p.' सुपथः; 'to seduce from the right p.' उत्पथं नी 1 P. -**less,** *a.* निष्पथ, अगम्य, दुर्गम.

Pathogenesis, *s.* रोगनिदानशास्त्रं.

Pathetic,-al, *a.* करुण, हृदयग्राविन्-ग्राहिन्, हृदिस्पृश्, हृदयंगम, करुणात्मक. -**ally,** *adv.* करुणं, हृदयग्राहितया; 'a speech p. worded' करुणार्थग्रथितं वचः' -**Pathos,** *s.* करुणो रसः, कारुण्यरसः, करुणारसः; रागः, रसः, कारुण्यं.

Pathology, *s.* रोगनिदानशास्त्र

Patient, *a.* क्षमिन्, सहिष्णु, तितिक्षु, सहनक्षमा-शील, सहन, क्षमावत्, मर्षिन्, क्षमायुक्त, क्षम-सह in comp. 2 धीर, शांत, धृतिमत्; 'very p.' बहुसह; 'p. of labour' क्लेशसह-क्षम; 'to be p.' सह् 1 A, क्षम् 1 A; *See* **Endure.**-*s.* आतुरः, रुग्णः, रोगिन् *m.* -**ly,** *adv.* क्षांत्या, क्षमापूर्वं, धीरतया. -**Patience,** *s.* क्षमा, तितिक्षा, क्षांति *f.*, सहिष्णुता. 2 धीरता, प्रशांति *f.*, धृति *f.*, धैर्यं, उत्साहः.

Patio, *s.* अंगणं-नं.

Patriarch, *s.* कुलपतिः, आदि-मूल-पुरुषः. 2 वृद्ध-गुरु-जनः. -**al,** *a.* (*s.*) in comp.

Patrician, *s.* कुलीनः, अभिजातः, कुलीनजनः, शिष्टः. -*a.* कुलीन, शिष्ट, सद्वंशज, अभिजात.

Patricide, *s.* *See* **Parricide.**

Patrimony, *s.* पैतृकरिक्थं-धनं, गोत्रधनं, पैतृकं, दायः, पित्र्यागतधनं. -**ial,** *a.* पितृप्राप्त-आगत, दायलब्ध, पैतृक (की *f.*).

Patriot, *s.* स्वदेशानुरागिन् *m.*, स्वदेशहितपरायणः, स्वदेशाभिमानिन् *m.* स्वदेशभक्तः. -**ic,** *a.* स्वदेशानुरागिन्, स्वभूम्यनुरक्त, स्वदेशाभिमानिन्, स्वदेशभक्त-आसक्त. -**ically,** *adv.* स्वदेशहितेच्छया. -**ism,** *s.* स्वदेशप्रीति *f.*-अनुरागः, जन्मभूमिवात्सल्यं. स्वदेशाभिमानः.

Patrol, *v. i.* (रक्षणार्थं) रात्रौ परिक्रम् 1 U, 4 P or परिभ्रम् 1, 4 P. -*s.* रक्षिणः, नागरिकाः (pl.), रक्षकः, रक्षिन् *m.*, रात्रिपरिचरः.

Patron, *s.* संभावयितृ *m.*, पालकः, उपकारकः. संवर्धकः, आश्रयः, पुरस्कर्तृ *m.*, रक्षकः, शरणं; नाथः, पोषकः, पिंडदः. -**age,** *s.* संभावना, आश्रयः, साहाय्यं, अनुग्रहः, उपकारः, पालनं, पोषणं, रक्षणं, संवर्धनं, अवलंबः, पुरस्कारः. -**al,** *a.* रक्षक, वर्धक. -**ize,** *v. t.* सं-भू c., आश्रयं दा 3 U, प्रति-अनु-पा c. (पालयति), अनुग्रह् 9 P, अवलंब् 1 A, संवृध् c.; oft. by (*s.*) with भू 1 P -**less,** *a.* निराश्रय, अनाथ, अशरण, निरवलंब, निराधार.

Patronymic, *s.* पैतृकनामन् *n.*, गोत्रनाम, अपत्यवाचकः; 'chapter treating of Taddhita p. terminations' तद्धितापत्याधिकारप्रकरणं.

Patten, *s.* काष्ठपादुका.

Patter, *v. i.* पटपटायते (D.). -*s.* पटपटाशब्दः.

Pattern, *s.* आदर्शः, निदर्शनं, उपमा, प्रतिमा, प्रतिरूपं-कृति *f.* 2 आकारः, रूपं, संस्कारः; *See* **Model.**

Paucity, *s.* अल्पता, स्तोकता, ex. by 'few' q. v.

Paunch, *s.* पिचिंडः, उदरं, जठरः-रं, तुंदं, लंबोदरं; 'having a p.' लंबोदर, तुंदिन, पिचिंडिल; *See* **Corpulent.** -*v. t.* निरंत्रीकृ 8 U.

Pauper, *s.* अनाथः, आकिंचनः, दरिद्रः, भिक्षुः, भिक्षाजीविन्; *See* **Beggar, Poor.** -**ism,** *s.* भिक्षावृत्ति *f.*, भैक्ष्याजीवः, भैक्ष्यं.

Pause, *v. i.* वि-उप-रम् 1 P, निवृत् 1 A; विश्रम् 4 P, शम् 4 P, विच्छिद् pass.; 'p. upon' सं-,चिंत् 10: *See* **Consider.** -*s.* विरामः, विरति *f.*, निवृत्ति *f.*, विच्छेदः, विश्रामः, प्र-उप-शमः. 2 अंतरं, व्यवधानं, अवकाशः, अंतरालं. 3 अवसानं, यतिः (in poetry).

Pave, *v. t.* प्रस्तरैः-इष्टकाभिः-खच् 10 (खचयति) or आस्तृ 9 U,-स्तृ 5 U, (भूमिं)

निर्मंथ् 9 P. **-er,** *s.* शिलास्तरणकृत् *m.* **-ment,** *s.* कुट्टिमः-मं, निबद्धा भूः, शिलास्तरःफलकं.

Pavilion, *s.* मंडपः-पं, पटमंडपः-वासः; *See* **Tent.**

Paw, *s.* पादः, सनखः पादः. 2 हस्तः, करः, चपेटः. *-v.* पादेन-खुरेण (भूमिं) अभिहन् 2 P or निलिख् 6 P. 2 करेण स्पृश् or परामृश् 6 P.

Pawn, *v. t.* निक्षिप् 6 P, न्यस् 4 U, आ-धा 3 U, न्यासीकृ 8 U, आधीकृ. *-s.* न्यासः, निक्षेपः, आधिः, बंधकः, पणः; *See* **Pledge.** 2 (At chess) शा(सा)रः-रिः; 'p.-broker' निक्षेपस्वव्यवसायिन् *m.*

Pay, *v. t.* दा 3 U, 1 P. 2 सं-पद् c., संप c., साध् c.; (a person) वेतनं-मूल्यं-दा; (debt) परि-,शुध् c., अपाकृ 8 U, अपवृज् 10, प्रतिकृ; 'p. for' निस्तॄ 1 P, निष्कृ; 'he paid for the book' तस्य पुस्तकस्य मूल्यं स ददौ; 'they paid for their offence with their lives' जीवितव्ययेन स्वापराधस्य निष्क्रयः कृतः; *See* **Cost.** *-s.* वेतनं, भृति *f.*, मूल्यं, निर्वेशः; *See* **Hire;** 'p.-day' वेतनदानदिवसः; 'p.-master' वेतनाध्यक्षः. **-ee,** *s.* परि-,ग्रहीतृ *m.* **-er,** *s.* दातृ *m.* शोधकः. **-ment,** *s.* दानं, शोधनं, निराकरणं, निस्तारः, साधनं, 'p. of a debt' ऋणमुक्ति *f.*-शोधनं, आनृण्यं.

Pea, *s.* कलायः, स(सा)तीनकः, सतीलकः, हरेणुः, रेणुकः.

Peace, *s.* संधिः, संधानं; 'to make p.' सं-धा 3 U. 2 शमः, प्र-उप-शमः-शांति *f.*, निर्वृति *f.*, स्वास्थ्यं, स्वस्थता, शांतता, सुखं; निरुद्वेगः, उपप्लवाभावः. 3 ऐक्यं, सख्यं, मैत्री, अविरोधः, संवादः. 4 मौनं, तूष्णींभावः, 'p. of mind' स्वास्थ्यं, चित्तप्रसादः, मनःशांतिः; 'hold p.' तूष्णीं भू, वाचं यम् 1 P, मौनीभू; 'p.-maker' संधातृ *m.* 'p.-offering' शांतिहोमः. *-interj.* शांतं, तूष्णीं भव. **-able,** *a.* प्र-,शांत, शांतप्रकृति-स्वभाव, अक्षुब्ध, प्रसन्न, निराकुल, अव्यग्र, अनुद्विग्न, स्वस्थ. 2 शांतिप्रिय, युद्ध-कलह-विमुख (खी *f.*). **-ableness,** *s.* शांतता, स्वास्थ्यं. 2 युद्धद्वेषः, कलहविमुखता. **-ful,** *a.* प्र-,शांत, निरुपद्रव, निरुपप्लव, निष्कंटक, विग्रहसंग्राम-हीन. 2 (Life &c.) निर्वृत, स्वस्थ, निरुद्वेग, सुख, in comp.; *See* **Peaceable.** **-fully,** *adv.* शांतं, निरुद्वेगं, स्वस्थं, शांतप्रसन्न-चेतसा. 2 युद्धं विना, साम्ना, सामोपायेन.

Peacock, *s.* मयूरः, नीलकंठः, शिखंडिन् *m.*, शिखी, बर्ही, बर्हिणः, शिखावलः. केकी, भुजंगभुक्, कलापी, मेघनादानुलासी, चन्द्रकी; 'p.'s tail' शिखंडः, बर्हः, पिच्छं, कलापः; 'p.'s crest' शिखा, चूडा; 'eye in the tail' चंद्रकः, मेचकः; 'p.'s cry' केका. **-Peafowl,** *s.* मयूरः-री, मयूरजाति *f.* **-Peahen,** *s.* मयूरी, शिखंडिनी, बर्हिणी.

Peak, *s.* शिखरः-रं, शृंगं, कूटः-टं, सानु *m. n.*, चूडा, ककुदः-दं, पर्वताग्रं. 2 (Generally) अग्रं, शिखरं, शिखा, चूडा. **-ed,** *a.* शिखरिन्, शृंगिन्, सकूट, ककुद्मत्. 2 तीक्ष्णाग्र, सूच्यग्र.

Peal, *s.* ध्वनिः, रवः, नि-,नादः, महाध्वनिः, निर्घोषः; *See* **Noise;** 'p. of thunder' घनगर्जितं, मेघनिर्घोषः, स्तनितं; 'p. of bells' घंटानादः, क्वणितं. *-v. i.* नद्, स्वन्, क्वण्, ध्वन् 1 P; स्तन्, गर्ज् 1 P (of thunder).

Pearl, *s.* मुक्ता, मुक्ताफलं, मौक्तिकं, शुक्तिजं; 'p.-shell' शुक्ति *f.*, मुक्तास्फोटः, शुक्तिका, मुक्तागारं. **-y,** *a.* मुक्तामय (यी *f.*), मुक्तापूर्ण. 2 मुक्तोपम, मुक्ताभ.

Peasant, *s.* कृषकः, कृषीवलः, क्षेत्रिकः, ग्राम्यः, ग्रामीणः, जानपदः; *See* **Farmer.** **-ry,** *s.* कृषीवलाः, कृषकवर्गः.

Pease, *s.* pl. *See* **Pea.**

Pebble, *s.* उपलः, दृषत्कणः, चूर्णखंडः, शर्कराखंडः. **-y,** *a.* प्रचुरोपल, उपलसंकीर्ण, शर्करिल, सशर्कर, शार्करीय.

Peccable, *a.* पापवश-अधीन.

Peccadillo, *s.* स्खलितं, अल्प or क्षुद्र-दोषः or अपराधः.

Peccant, *a.* पापिन्, अपराधिन्, दोषिन्, सदोष, पापशील. 2 दुष्ट, दूषित, विकृत. **-Peccancy,** *s.* विकारः, दोषः.

Peccavi, *s.* दोषस्वीकारः.

Peck, *v.* (चंचुपुटेन) अभिहन् 2 P, तुद् 6 P, प्र-हृ 1 P, वि-,लिख् 6 P, दंश् 1 U, तुंडेन खंड् 10, चंचुप्रहारं कृ 8 U, चंचुप्रहारेण जर्जरीकृ. 2 (Grain) चंच्वा ग्रह् 9 U or आ-दा 3 A or लिह् 2 U; 'p. at' सततं प्रहृ 1 P, निंद् 1 P; *See* **Censure.** *-s.* द्रोणपादः. **-er,** *s.* प्रतुदः.

Pectoral, *a.* उरस्य. 2 कासघ्न (घ्नी *f.*). *-s.* कासघ्नं, कफ-श्लेष्म-घ्नं.

Peculate, *v. i.* छलेन आत्मसात्कृ 8 U or ग्रस् 1 A, or मुष् 9 P or अपहृ 1 P. **-ion,** *s.* छलेन अपहारः, ग्रसनं, मोषणं. **-or,** *s.* मोषकः.

Peculiar, *a.* विशेष in comp.; विशिष्ट, असाधारण (णी *f.*), असामान्य, अव्यापक; आत्मीय, स्वीय; *See* **Particular.** *-s.* असाधारणधर्मः, स्वीयं धनं. **-ity,** *s.* विशेषधर्मः-लक्षणं-चिह्नं-गुणः, विशेषः, धर्मः, गुणः. **-ly,** *adv.* विशेषतः, विशेषेण, सविशेषं.

Pecuniary, *a.* अर्थ-धन-द्रव्य-in comp.; 'p. loss' अर्थहानिः; 'p. difficulty' अर्थकृच्छ्रं. 2 धन-द्रव्य-रूप, अर्थात्मक.

Pedagogue, *s.* बालशिक्षकः-पाठकः. 2 **Pedant,** q. v.

Pedal, *a.* पादविषयक, पादसंबंधिन्.

Pedant, *s.* पंडितंमन्यः, पंडितमानिन् *m.*, विद्यागर्वितः. **-ic, ical,** *a.* पांडित्यदर्शिन्, समुद्धत. **-ically,** *adv.* विद्याभिमानेन. **-ry,** *s.* विद्यावलेपः, पांडित्यदर्पः, दंभार्थं पांडित्यदर्शनं.

Peddler, *s. See* **Pedler.**

Pedestal, *s.* (स्तंभादेः) पादः, आधारः; स्तंभतलं, फलकः.

Pedestrian, *s.* पदातिः, पादचारिन् *m.*, प-(पा)द्गः, पादगतः; *See* **Foot-soldier.** **-***a* पादग, पादचारिन्-गामिन्, पाद् in comp **-ism,** *s.* पादचारः, पादगमनं.

Pedicle, Pedicel, *s.* मंजरि-री *f.* **2** वृंतं, प्रसवबंधनं.

Pedicular, *a.* यूकापूर्ण.

Pedicure, *s* पादरोगवैद्यः. **2** पाद.वेक्षा.

Pedigree, *s.* वंशावलि-ली *f*, अन्वयः, वंशः, कुलं. **2** वंशावलिपत्रं, वंशचरितं.

Pedler, *s.* (भ्रमन्) भांडवाहः, क्षुद्रद्रव्यविक्रयिन् *m.*

Peduncle, *s.* वृंतं, प्रसव-पुष्प-बंधनं.

Peel, *s.* त्वच् *f.*, वल्कं, चर्मन् *n.*, शल्कं **-***v. t.* त्वचं अप-नी 1 P or निष्कुष् 1 P or निर्हृ 1 P, त्वचयति (D), निस्त्वचीकृ 8 U, त्वक्ष् 1 P. **-***v. i.* निस्त्वचीभू 1 P. **-ing,** *s.* त्वक्षणं, त्वग्निष्कर्षः.

Peep, *v. i.* जालमार्गेण दृश् 1 P or वीक्ष् 1 A, प्रच्छन्नं ईक्ष्, सूक्ष्मं निरूप् 10; जालांतरप्रेषितदृष्टिरन्या (R. vii. 9) 'another p. ing through a window.' **2** शनैः उद्-गम् 1 P or उद्-इ 2 P or प्र-निर्-भा 2 P, प्रकाश् 1 A, दृश्-लक्ष्-pass., प्रादुः-आविः-भू 1 P. **3** विरु 2 P, कूज् 1 P. **-***s.* जालमार्गेण वीक्षणं, सूक्ष्मनिरूपणं-वीक्षणं-दृष्टिः *f.* **2** पूर्वप्रथम-दर्शनं-आलोकः-प्रकाशनं; 'p.-hole' जालमार्गः-रंध्रं, सूक्ष्मरंध्रं, जालांतरं.

Peer, *s.* वयस्यः, सहायः, तुल्यः, तुल्य-समपदस्थः. **2** कुलीनः, अभिजातः, शिष्टजनः. **-***v. i.* **Appear,** q. v. **2 Peep,** q. v. **-er,** *s.* सूक्ष्मनिरूपकः. **-ess,** *s.* कुलीना. **-less,** *a.* अतुल, अनुपम, अप्रतिम; *See* **Matchless.**

Peevish, *a.* पिशुन, प्रतीप, वक्र, वक्र-वामशील, दुःशील, कर्कश, रूक्षभाव, दुष्टप्रकृति. **2** कलहप्रिय, कोपन. **-ly,** *adv.* प्रतीपं, वक्रभावेन. **-ness,** *s.* पैशुन्यं, वक्रभावः-शीलं, रूक्षस्वभावः, दुःशीलता, कार्कश्यं.

Peewit, *s. See* **Lapwing.**

Peg, *s.* नागदंतः, भारयष्टि *f.*, विहंगिका; 'p. of a lute' कूणिका; 'iron p.' कीलः-लकः. **-***v t* नागदंते अवलंब् c. or बंध् 9 P.

Pelf, *s.* अन्यायार्जितं धनं.

Pell, *s. See* **Skin,** or **Hide** *s.*

Pellet, *s. See* **Pill.**

Pellicle, *s.* तनुत्वच् *f.*, सूक्ष्मचर्मन् *n.*, पटलं, पुटः-टं.

Pell-Mell, *adv.* संकुलं, संकीर्णं, क्रमं विना.

Pellucid, *a.* स्वच्छ, निर्-वि-मल, विशद, प्रसन्न, शुद्ध. **-ity,** *s.* **ness,** *s.* स्वच्छता, निर्मलता, वैशद्यं, प्रसादः.

Pelt, *v. t.* (लोष्टैः) प्रहृ 1 P, तड् 10, अभि-, हन् 2 P, आहन् 2 U; 'he was p. ed to death' लोष्टघातं हतः. **3** तीव्रं-बलवत्-वृष् 1 P, धारासारेण वृष्; 'there was a p. ing shower of rain' धारासारेण महती वृष्टिर्बभूव (H. 3). **-***s.* चर्मन् *n.*, दृति *f.*, कृत्ति *f.* **2** प्रहारः, आघातः.

Pelvis, *s.* बस्तिदेशः.

Pen, *v. t.* लिख् 6 P, पत्रे निर्विश् c. **2** (व्रजे) नि-अव-रुध् 7 U. **-***s* लेखनी, कलमः, अक्षरतूलिका, तूलिका, वर्णिका (painter 's p.). **2** व्रजः, अवरोधः; 'cow-p.' गोशाला, गोष्ठं; 'p.-man' लिपिज्ञः, लेखकः, लेखनकुशलः; 'p.-manship' लिपि *f.*, लेखनविद्या, लेखनचातुर्य-कौशलं. **-Pent,** (up) *a.* नि-अव-रुद्ध; 'p. house' उपगृहं.

Penal, *a.* दंडार्ह, दंडनीय, दंड्य. **2** दंडविषयक. **-ty,** *s.* दंडः, निग्रहः, शासनं. **2** साहसं, अर्थ-धन-दंडः.

Penance, *s.* तपस् *n.*, तपस्या, तपश्चर्या, कृच्छ्रं, यमः, कायक्लेशः; 'imposed p.' प्रायश्चित्तं; 'practise p.' तपः तप् 4 A or आचर् 1 P, तपस्यति (D).

Penchant, *s. See* **Inclination.**

Pencil, *s.* तूलिका, तूलि *f.*, वर्तिका, ईषिका; लेखनी. **-***v. t.* लिख् 6 P, वर्तिकया लिख् or अंक् 10.

Pendant, *s.* कर्णावतंसः, कुंडलं, ललंतिका, लोलकः.

Pendent, *s.* वि-,लोल, चल, प्रलंबमान, प्रलंब, आलंबिन्, आ-प्र-लंबित.

Pending, *a.* अनिर्णीत, अनिश्चित, अनिष्पन्न; 'p. the decision' यावन्निर्णयो न कल्पते.

Pendulous, *a.* प्र-,लंब, लंबिन्, लंबित, लोल.

Pendulum, *s.* लोलकः, लोलदंडः.

Penetrate, *v. t.* प्र-आ-विश् 6 P, निर्-,भिद् 7 P, व्यध् 4 P, छिद् 7 P, गाह् 1 A (forest &c.); निखन् 1 P. **2** व्याप् 5 P, मुर्छ् 1 P, (छाया न मूर्च्छति मलोपहतप्रसादे दर्पणतले S. 7). **3** अर्थं बुध् 1 P or ज्ञा 9 U, आशयं ग्रह् 9 U. **-ion,** *s.* प्रवेशः-शनं, भेदः-दनं, वेधः-धनं. **2** व्याप्ति *f.*, मूर्च्छनं. **3** अर्थबोधः, अर्थ-आशय-ज्ञानं. **4** (Power of p.) ग्रहणसामर्थ्यं, कुशाग्रसूक्ष्म-मति *f.* or बुद्धि *f.*, तीक्ष्ण or सूक्ष्मबुद्धित्वं or मतित्वं, वैदग्ध्यं; 'a man of p.' सूक्ष्ममतिः, कुशाग्रबुद्धिः, विदग्धः, मर्मज्ञः, मार्मिकः. **-ing, -ive,** *a.* प्रवेशक, भेदिन्,

वेधिन्, भेदक. 2 व्यापक, व्यापिन्. 3 सूक्ष्म or तीक्ष्ण-मति or -बुद्धि, कुशाग्रमति-बुद्धि, विदग्ध, मर्मज्ञ, मर्मवेदिन्.

Peninsula, *s.* द्वीपकल्पः-ल्पं. -r, *a.* द्वीपकल्परूप; द्वीपकल्पस्थ.

Penis, *s.* लिंगं, उपस्थः, शिश्नः, मेढ्रः, मेहनं, शेफस् *n.*, चर्मदंडः.

Penitent, *a.* अनुशयिन्, अनुतापदग्ध, जातकृत-अनुताप. **-ial,** *a.* अनुतापजनित, अनुशयार्थक, पश्चात्तापरूप. **-iary,** *s.* प्रायश्चित्तागारं, कारावासः. **-ly,** *adv.* सानुशयं, सपश्चात्तापं. **-Penitence,** *s.* अनुतापः, पश्चात्तापः, अनुशयः, अनुशोकः; *See* **Repentance.**

Pennant, Pennon, *s.* ध्वजः, पताका, केतुवसनं; *See* **Banner.** **-Pennate,** *a.* सपक्ष, पक्षयुक्त.

Penny, *s.* मुद्रा. **-Penniless,** *a.* आकिंचन, निर्धन; *See* **Poor.**

Pensile, *a. See* **Pendent.**

Pension, *s.* (भूत-पूर्व-सेवार्थं) वृत्ति *f.*, वेतनं, वार्षिकं. **-v.** *t.* (भूत-पूर्व-सेवार्थं) वृत्तिं दा 3 U. **-er,** *s.* वृत्तिभुज् *m.*, वृत्तिभोगिन् *m.*

Pensive, *a.* चिंता or ध्यान-पर or परायण, सचिंत, चिंताक्रांत, उन्मनस्क, उदासीन; 'in a p. mood' सचिंतमुखा, गंभीरं. **-ly,** *adv.* सचिंतं, ध्यानपूर्वं. **-ness,** *s.* ध्यानपरता, विषादः, खेदः.

Pentachord, *s.* पंचतंत्रीवाद्यं.

Pentagon, *s.* पंचभुजः. **-al,** *a.* पंचकोण, पंचभुज.

Pentangular, *a.* पंचकोण, पंचास्र.

Penult, *s.* उपांत्याक्षरं. **-imate,** *a.* उपांत्य; 'p. letter' उपधा, उपांत्यं.

Penumbra, *s.* खंडच्छाया.

Penury, *s.* दारिद्र्यं, निर्धनता, दुर्गति *f.* **-ious,** *a.* दीन, निर्धन, निःस्व; *See* **Poor.** 2 कृपण, क्षुद्र, कदर्य; *See* **Miserly.**

Peon, *s.* भृत्यः, पदातिः; *See* **Servant.**

People, *s.* जनः, लोकः, प्रजा, (pl. also); जनता, देशवासिनः, प्रकृतयः (pl.); 'country p.' ग्रामीणाः, ग्रामीयजनः, जानपदाः; 'common p.' प्राकृताः, इतरे-पृथग्-जनाः, सामान्य or प्राकृत-जनाः or लोकाः. 2 वर्गः, गणः, वर्णः, जनः, लोकः. 3 सेवकजनः-गणः, परिवारः. **-v.** *t.* जनैः पूर् 10 or आकॄ 6 P, वस् c.

Pepper, *s.* मरी(रि)चं, कालकं, वेल्लजं, कृष्णं, ऊषणं, धर्मपत्तनं; 'long p.' पिप्पली; *See* under **Long.** **-v.** *t.* अवकॄ 6 P.

Pepsin, *s.* जाठररसविकारः.

Peptic, *a.* पाचक, पाचन, दीपन, अग्निद.

Peracute, *a.* अतितीक्ष्ण, अतितीव्र.

Peradventure, *adv.* कदापि, कदाचित दैवात्, दैववशात्.

Perambulate, *v. t.* परि-इ 2 P, परिक्रम् 1 U, 4 P, परिभ्रम् 1, 4 P, पर्यट् 1 P, परि-सृ-गम् 1 P; इतस्ततः चल्-चर् 1 P. **-ion,** *s.* परिक्रमः-मणं, परिभ्रमणं, पर्यटनं.

Per annum, *adv.* प्रतिवर्षं, प्रतिवत्सरं.

Perceive, *v. t.* उपलभ् 1 A, ज्ञा 9 U, वि-बुध् c., बुध् 1 P, ग्रह् 9 U, अवगम् 1 P, अव-इ 2 P, अनुभू 1 P, विद् 2 P; *See* **Know.** 2 (By the eye) दृश् 1 P, ईक्ष् 1 A, निरूप् 10, आ-,लक्ष् 10, आलोक् 1 A, 10; *See* **See.** **-ed,** *a.* ज्ञात, विदित, उपलब्ध, गोचर; 'p. by the senses' इंद्रियगोचर. **-er,** *s.* लक्षकः. **-Perceptible,** *a.* वेद्य, उपलभ्य, प्रत्यक्ष, दृष्टिगोचर, व्यक्त, परिस्फुट, सुस्पष्ट; oft. by विषय, गोचर, ग्राह्य in comp.; 'p. by the eye' प्रत्यक्ष, चाक्षुष, दृष्टिगोचर; कर्णविषय, इंद्रियगोचर, &c. **-Perceptibly,** *adv.* प्रत्यक्षं, प्रत्यक्षतः. **Perception,** *s.* उपलब्धि *f.*, ग्रहणं; बोधः, अवगमनं, अनुभवः, वेदनं, विभावनं, ज्ञानं, व्यक्ति *f.* 2 (Power of p.) ग्राहकत्वं, ग्रहण वेदन-शक्ति *f.*, विषयानुभवः, चैतन्यं, चिच्छक्ति *f.* **-Perceptive,-Percipient,** *a.* ग्रहणक्षम, ग्राहिन्, ग्राहक, विषयग्रहणसमर्थ, चेतन.

Per cent, *adv.* Ex. by उत्तर in comp; '5 p.' पंचोत्तरं शतं.

Perch, *s.* वासयष्टि *f.*, खेलनयष्टिः, यष्टिः, दंडः. **-v.** *i.* अध्यास् 2 A (with acc.), नि-ली 4 A, निषद् 1 P (with loc.); सं-डी 1 A (of birds.).

Perchance, *adv. See* **Perhaps.**

Percolate, *v. i.* कणशः-लवशः स्रु-क्षर्-गल् -1 P or स्यंद् 1 A. *v. t.* शुध् c., बिंदुशो-लवशः स्रु c. or गल् c. **-ion,** *s.* [illegible] क्षरणं-स्रवणं-गलनं.

Percussion, *s.* समाघातः, संघट्टः, आ-प्रति-घातः.

Perdition, *s.* उच्छेदः, क्षयः, वि-प्र-णाशः. 2 अधोगति *f.*, अधःपातः, नरक-निरय-पातः; 'p. (ruin) seize thee' (cf. 'Murrain take thee') अकरणिः-अजीवनिः-अवग्राहः-निग्राहः-ते भूयात्.

Perdue, *a.* प्रच्छन्न, गूढ.

Perdurable, *a.* चिरस्थायिन्.

Peregrinate,-ion, *See* **Travel.**

Peremptory, *a.* सुनिश्चित, निर्णीत, नियत; अविशंक्य, अवैकल्पिक (की *f.*), पारेच्छिक, अवश्यक. 2 स्पष्ट, परिस्फुट, उद्घट्टक, निरर्थ; 'p. order' अलंघनीयः-अनतिक्रमणीयः-आदेशः; 'the command of elderly persons is (to be considered as) p.' आज्ञा गुरूणां ह्यविचार-

ग्रीवा (R. xiv. 46). 3 दृढ-स्थिर-मति, अध्यवसायिन्, दृढसंकल्प. -ily, *adv.* सुनिश्चितं, सुव्यक्तं, भिन्नार्थं, सुस्पष्टं; दाढर्येन, दृढनिश्चयपूर्वं. -iness, *s.* स्पष्टता, दृढनिश्चयः, दृढता, अविलंबता.

Perennial, *a.* वर्षावधि, वर्षस्थायिन् 2 नित्य, अक्षय्य, निरंतर, अविरत.

Perfect, *a.* सिद्ध, संपन्न, निष्पन्न, समाप्त, परिणत. 2 अशेष, समग्र, सकल, सं-परिपूर्ण, समस्त, अविकल, अखंड, अक्षत, अन्यून, निर्दोष. 3 परम, उत्कृष्ट, विशिष्ट, उत्तम; निपुण, कुशल, अभिज्ञ, पारंगत, विशारद, प्रवीण, परिपक्व, संपन्न. 4 (In grammar) लिट्. -*v. t.* साध् c., सिध् c. (साधयति), सं-निः-पद् c., परि-सं-पूर् 10, समाप् c., निर्वृत् c.; ex. by कृ 8 U with (*a.*). -er, *s.* संपादकः, साधकः. -ion, -ness, *s.* सिद्धि *f.*, संपन्नता, समग्रता, अखंडता, संपरि-पूर्णता, निष्पत्ति-समाप्ति- *f.* 2 परिपाकः, परिणति *f.*, पक्वावस्था, उत्कृष्टता, उत्कर्षः, विशिष्टता, प्रकर्षः, परा कोटिः-काष्ठा. 3 नैपुण्यं, संपन्नता, कौशलं, विज्ञानं, प्रावीण्यं. 4 गुणः, परम-उत्तम-गुणः, विशेषः, प्र-उत्-कर्षः. -ive, *a.* साधक, संपादक, समापक, सिद्धिकर (री *f.*). -ly, *adv.* सर्वथा, सर्वशः, साकल्येन; समग्रं, संपूर्णं, अशेषतः, निःशेषं.

Perfidy, *s.* विश्वासघातः-भंगः-भेदः, असत्यसंधत्वं, प्रतिज्ञा-समय-भंगः; शत्रुसेवा, कापट्यं, वंचनं-ना. -ious, *a.* असत्यसंध, विश्वास or विश्रंभ-घातिन् or भेदिन्, भग्नप्रतिज्ञ वंचक, शठ, मिथ्याचार, शत्रुसेविन्. 2 (Of acts) अनार्य. -iously, *adv.* विश्वासघातेन, शठवत्, कैतवेन.

Perforate, *v. t.* आ-,व्यध् 4 P, छिद्रयति (D.), निर्भिद् 7 P, उत्-समुत्-कॄ 6 P, (मणौ वज्रसमुत्कीर्णे R. I. 4); 'un-p. ed jewel' अनाविद्धं रत्नं (S. 2.) -ed, *a.* विद्ध, सच्छिद्र, उत्कीर्ण, सरंध्र, सुषिर. -ion, *s.* वेधः-धनं, निर्भेदः. 2 छिद्रं, रंध्रं, विवरं, सुषिरं. -or, *s.* वेधनिका, आविधः, आस्फोटनी.

Perforce, *adv.* बलात्, बलेन, प्रसभं, प्रसह्य, बलवत्, बलात्कारेण.

Perform, *v. t.* कृ 8 U, निर्वृत् c., आचर् 1 P, सं-निः-पद् c., साध् 5 P or c., वि-धा 3 U, अनु-ष्ठा 1 P, निर्वह् c.; (promise) पूर् 10, वृ 1 P शुध् c., अपवृज् 10; (a sacrifice) आतन् 8 U, आहृ 1 P. 2 (On the stage) नट् 10, अभि-नी 1 P, प्रयुज् 7 A, 10; *See* Act; 'has not been (seen) p ed on the stage' न प्रयोगतो दृष्टं (Rat. 1). -ance, *s.* संपादनं साधनं, करणं, विधानं, निर्वर्तनं, अनुष्ठानं, आचरणं. 2 कार्यं, कर्मन् *n.*, क्रिया, कृति *f.*, व्यापारः, चेष्टा, चेष्टितं, प्रवृत्ति *f.*, चरितं. 3 प्रयोगः, अभिनयः, नाटनं. -er, *s.* कर्तृ *m.*, संपादकः, निर्वर्तकः, अनुष्ठातृ *m.* निर्वाहकः. 2 (In dramas) अभिनेतृ *m.*, नटः; प्रयोजकः. 3 वादकः.

Perfume, *v. t.* अधि-, वास् 10, धूप् 1 P, 10, धूपेन वास्, सुरभीकृ 8 U, परिमलयति-आमोदयति- (D.), भू c. -*s.* परिमलः, आमोदः, सुगंधः, सु-,वासः, सौरभं-भ्यं. 2 (Thing scented) गंधः, गंधद्रव्यं, गांधिकं. 3 (For the person) गात्रानुलेपनी; वर्ति *f.*, अनु-वि-लेपनं, वर्णकं; 'p. artificially made' कृत्रिम धूक-धूपः. -ed, *a.* सुवासित, सवास, सुरभीकृत, सामोद, धूपित, भावित. -er, *s.* गांधिकः, गंधोपजीविन् *m.*, गंधविक्रयिन् *m.* गंधवणिज् *m.*, गंधाजीवः. -ery, *s.* गंधद्रव्यं, गंधव्यापारः-विक्रयः. -ing, *s.* वासनं, भावनं. 2 (With unguents) चर्चा, चार्चिक्यं, अनु-वि-लेपनं, स्थासकः, अंगरागः.

Perfunctory, *a.* अनवहित, निरुत्साह, प्रमत्त, अनुत्कंठ; *See* Negligent. -ily, *adv.* अनवधानेन, निरुत्साहं. -iness, *s.* अनवधानं, अनास्था, निरुत्साहता.

Perhaps, *adv.* कदाचित्, दैवात्, कदापि, नु वा, किंस्वित्, स्यात्, or by pot.

Periapt, *s.* रक्षाकरंडः

Pericardium, *s.* हृदयकोशः, हृदाशयः.

Pericarp, *s.* बीजकोशः-शुक्ति *f.*

Pericranium, *s.* कपालावरणं.

Perigee, *s.* भीचतमं-नेदिष्ठं-स्थानं

Peril, *s.* भयं, शंका, संदेहः, संशयः. -*v. t.* संशये पत् c. -ous, *a.* संदिग्ध, सशंक, भयहेतुक; *See* Danger, Hazard.

Period, *s.* समयः, कालः, वेला, कालावधिः, अंतरं, अवधिः, नियतकालः. 2 कालचक्र-पर्यायः-आवर्तः, वर्षचक्रं, युगं. 3 अंतः, अवसानं, विरामः. 4 पूर्णवाक्यं, वाक्योच्चयः, पूर्णविरामः; 'p. of life' वयः, वयोवस्था; 'last p.' चरमवयः, अंत्यावस्था. -ic, -ical, *a.* नित्य, अनुकालिक-नियतकालिक-सामयिक-(की *f.*). -*s.* सामयिकपुस्तकं; 'a monthly p.' मासिकपुस्तकं. -ically, *adv.* काले काले, समयतः, कालानुरूपं, नियतकाले.

Periosteum, *s.* अस्थित्वच् *f.*

Peripatetic, *a.* इतस्ततः-भ्रमन्-भ्रमणशील.

Periphery, *s.* परिवेशः-षः. परिधिः, परिणाहः. 2 नेमि-मी *f.*, प्रधिः.

Periphrase, Periphrasis, *s.* वाग्प्रपंचः वाग्विस्तरः, वाग्बाहुल्यं-प्रपंचः. -*v. t.* प्रपंचयति (D.), वाग्विस्तरेण वर्ण् 10 or व्या-ख्या 2 P. -Periphrastic, *a.* बहुवाक्य, बहुपद; 'p. future' लुट्.

Perish, *v. i.* नश् 4 P, प्र-वि-°, क्षि-pass.; प्रमी 4 A, ध्वंस् 1 A, क्षयं-नाशं-ध्वंसं-नाश

1 P or मृ-म्ला 2 P, प्र-वि-ली 4 A; मृ 6 A, व्यापद् 4 A; *See* **Die.** **-able,** *a.* वि-, नश्वर (री *f.*), विनाशधर्मन्, भंगुर, क्षयिन्, वि-,ध्वंसिन्, क्षयिष्णु, क्षय-नाश-शील, लयाधीन; 'p. in a moment' क्षणिक, क्षणभंगुर.

Peristyle, *s.* स्तंभपंक्ति-श्रेणी *f.*

Peritoneum, *s.* अंत्रवेष्टनं.

Perjure, *v. t.* साक्ष्ये मिथ्या-अनृतं वद् 1 P, मिथ्या शप् 1, 4 U, कूटसाक्ष्यं कृ 8 U. **-ed, -er,** *a., s.* कूटशपथकारिन्, मिथ्याशपथक, कूटसाक्षिन्. **-y,** *s.* कूट or मिथ्या-साक्ष्यं or [शपनं.

Perk,-y, *a. See* **Saucy.**

Permanent, *a.* नित्य, स्थिर, नित्य-चिर-स्थायिन्, ध्रुव, अक्षय, स्थावर; *See* **Lasting.** **-ly,** *adv.* नित्यं, स्थिरं, ध्रुवं, शाश्वतं, सर्वकालं. **-Permanence,-cy,** *s.* स्थिरता, स्थायित्वं, ध्रुवता, नित्यता, अक्षयता, अनपायः, सनातनत्वं. 2 प्रतिष्ठा, स्थिति *f.*, (कुलस्य स्थित्यै K. I. 18), (वृक्षरथस्य कुलं प्रतिष्ठां गतं U. 5).

Permeate, *v. t.* व्याप् 5 P, व्यश् 5 A; *See* **Pervade.** 2 प्र-विश् 6 P, भिद् 7 P, गाह् 1 A. **-ion,** *s.* व्याप्ति *f.*, प्रवेशः, भेदनं. **-Permeable,** *a.* व्याप्य, भेद्य, प्रवेश्य.

Permit, *v. t.* अनु-ज्ञा 9 U, अनुमन् 4 A, अनुरुध् 1 A, आज्ञां दा 3 U. *See* **Allow.** **-s.** अनुज्ञा-अनुमति-पत्रं, अनुज्ञा. **-Permissible,** *a.* अनुज्ञेय, अनुमंतव्य, अनुज्ञार्ह. 2 धर्म्य, न्याय्य, ग्राह्य, युक्त; *See* **Lawful.** **-Permission,** *s.* अनुज्ञा, अनुमति *f.* -नं, अनुमोदनं, आदेशः, आज्ञा. **-Permissive,** *a.* अनुज्ञाप्रद, अनुमोदक; अनवश्यक.

Permute, *v. t.* वि-नि-मे 2 A, परि-वृत् 1 A. **-ation,** *s.* वि-,निमयः, परिवर्तः, परिवृत्ति *f.*, व्यतिहारः. 2 अंकपाशः.

Pernicious, *a.* घातक, अपकारक, वि-, नाशक, हिंस्र, हिंसक, अपकारिन्, दुष्ट, गर्ह्य; *See* **Injurious.** **-ly,** *adv.* सापकारं, सापायं, सनाशं.

Peroration, *s.* उपसंहारः.

Perpendicular, *a.* लंब, लंबरूप; सरल, ऋजु, अकुटिल. **-s.** लंबः. **-ly,** *adv.* लंबरूपेण, सरलं, ऋजु.

Perpetrate, *v. t.* कृ 8 U, वि-धा 3 U, आचर् 1 P; *See* **Commit.**

Perpetual, *a.* नित्य, सतत, शाश्वत (ती *f.*), अविच्छिन्न, अविरत, संतत, निरंतर, सनातन (नी *f.*), अनंत, नित्य-चिर-स्थायिन्. **-ly,** *adv.* नित्यं, सदा, नित्यशः, शाश्वतं, शश्वत्, सततं, अविरतं **-Perpetuity,** *s.* अविच्छेदः, नित्य-चिर-स्थायिता, आनंत्यं, नित्यता, अविरामः, नैरंतर्यं, अक्षयस्थिति *f.*, सनातनत्वं; 'to p.' शाश्वतीः समाः. **-Perpetuate,** *v. t.* स्थिरीकृ 8 U, कृ with (*a.*).

Perplex, *v. t.* मुह् c., आकुलीकृ 8 U, सं-वि भ्रम् c. (भ्रमयति), मोहं-संभ्रमं-उत्पद् c. 2 संकुलीकृ, संकीर्णीकृ, क्लिश् 9 P; *See* **Embarrass, Confuse.** **-ed,** *a.* आ-व्या-कुल, संभ्रांत, वि-,मूढ, कातर, व्यग्र, उद्विग्न, अधीर; व्याकुलचित्त, संशयापन्न, व्यस्त-मूढ-विक्षिप्त-चित्त. **-ing,** *a.* मोहक, संदिग्ध, भ्रम-मोह-कारिन्, मोहकर (री *f.*), मोहन, भ्रांतिजनक (की *f.*), विषम. **-ity,** *s.* व्या-, मोहः, आ-व्या-कुलत्वं-ता, संभ्रमः, व्यग्रता, चित्तविक्षेपः, व्यस्तचित्तत्वं, चित्तवैकल्यं, संशयः, संदेहः.

Perquisite, *s.* अधिकलाभः, हस्तलाभः; *See* **Gift.**

Persecute, *v. t.* प्र-सं-बाध् 1 A, अप-कृ 1 A, पीड् 10, उप-द्रु 1 P, क्लिश् 9 P, पीडार्थं अनुसृ 1 P, अभि-,द्रुह् 4 P. **-ion,** *s.* बाधा, उपद्रवः, उपप्लवः, पीडनं, अभिद्रोहः. **-or,** *s.* बाधकः, उपद्रवकारिन् *m.*

Persevere, *v. i.* मनः-चित्तं-अभिनिविश् c., सदा प्रवृत् 1 A, अभियुज् pass., अभिनिवेशेन सं-घट् c., सततं प्रयत् 1 A, अनवरतं चेष्ट् 1 A, निर्बंधं कृ, साग्रहं प्रवृत्; 'p. in your opposition' स्थिरप्रतिबंधो भव (S. 2); 'he who p. s in good actions सदाचारप्रवृत्तः, सदा सत्कर्मकारी. **-ance,** *s.* अभिनिवेशः, अध्यवसायः, उद्यमसातत्यं, दीर्घप्रयत्नः-उद्यमः-उद्योगः-उत्साहः, अतिनिर्बंधः, सदाभियोगः. 2 अनवरतचेष्टा, प्रवृत्ति *f.*, प्रसक्ति *f.*, धैर्यं, आग्रहः, उद्योगः, उद्यमः, व्यवसायः. **-ing,** *a.* अनिशं-अनवरत-उद्यमिन्, अभिनिविष्ट, अध्यवसायिन्, दीर्घोद्योगिन्, सदाप्रवृत्त, उत्साहवत्, आग्रह-निर्बंध-शील, प्रसक्त, प्रसित. **-ingly,** *adv.* अभिनिवेशेन, दीर्घोद्योगेन, प्रसक्तं, सोत्साहं, सनिर्बंधं.

Persist, *v. i.* साग्रहं प्रवृत् 1 A, अतिनिर्बंधेन आचर् 1 P, पर्यव-स्था 1 A; *See* below; 'do not p. in your wickedness' दुराचरितेषु मा ते निर्बंधो भूत्; *See* **Persevere.** **-ence,-cy** *s.* निर्बंधः, आग्रहः, अभिनिवेशः, पर्यवस्थानं, दुराग्रहः. **-ent,** *a.* निर्बंधपर, साग्रह; *See* **Obstinate.** **-ently,** *adv.* साग्रहं, निर्बंधेन.

Person, *s.* पुरुषः, नरः, जनः, व्यक्ति *f.*; 'this p.' अयं जनः (referring to the speaker); 'a female p.' स्त्रीजनः, अंगनाजनः. 2 शरीरं, अंगं, वपुस् n., देहः, कायः, तनु *f.*, गात्रं, *See* **Body.** 3 रूपं, आकारः, आकृति *f.*, मूर्ति *f.*; 'an enemy in the p. of K[illegible]' [illegible] 4 पात्रं, भूमिका. 5 पुरुषः (in grammar). 'in p.' स्वयं, स्वतः, आत्मना, साक्षात्, प्रत्यक्षं. **-able,** *a.* सुरूप, सुगात्र (त्री *f.*),

शोभनाकार. -age, *s.* पुरुषः, जनः, नरः, व्यक्तिः. 2 श्रेष्ठ-विशिष्ट-जनः. -al, *a.* व्यक्तिगत, पुरुषविशेषसंबद्ध, विशिष्टजनोद्दिष्ट. 2 शारीरिक-दैहिक- (की *f.*), शरीर-अंग in comp. 'p. beauty' अंगसौष्ठवं; 'p. graces' शरीरलावण्यं, 'p. union' शरीरसंबंधः; 'p. attendant' आसन्नपरिचारकः; 'p. attendance' शरीर-चर्या-शुश्रूषा. 3 स्वयंकृत, स्व-आत्म-कृत, साक्षात्कृत. 4 आत्मन्, स्व. निज in comp., 'for p. profit' आत्म-स्व-हिताय; 'p. experience' स्वानुभवः 5 पुरुष-व्यक्ति-वाचिन्, पुरुष in comp. 6 अस्थावर, जंगम. -ality, *s.* व्यक्तिगताक्षेपः, विशेष-व्यक्ति-निर्देशः, व्यक्त्युद्देशः, व्यक्तिसंस्पर्शः. 2 व्यक्तिः, पृथक्त्वं, स्वत्वं. -ally, *adv.* स्वयं, स्वतः, प्रत्यक्ष-क्षतः, साक्षात्. 2 व्यक्तितः, पृथक्.

-Personate, *v. t.* रूपं-वेषं ग्रह् 9 U or धृ 1 P, 10 or आ-स्था 1 U (with gen.), छद्म-कूटं-कृ 8 U; oft. ex. by वेश or रूप in comp., or by denom.; 'p. ing Nala' नलरूपमास्थाय, नलरूपः, नलवेशधारिन् 'p. s a king' नृपायते, राजायति. 2 अभि-नी 1 P, नट् 10, रूप् 10. -ion, *s.* रूप-वेश-धारणं-ग्रहणं. 2 अभिनयः, नाटनं. -or, *s.* वेशधारिन्-भृत् *m.* 2 अभिनेतृ *m.* -Personify, *v. t.* चेतनत्वं-चेतनभावं-आरुह् c. (रोपयति), (अचेतने) चेतनवदुपचर् 1 P, (अचेतनेऽपि चेतनवदुपचारदर्शनात् S. B.99) -ed, *a.* Ex. by मूर्ति *f.*, मूर्तशरीरिन्-*a.* इव or साक्षात्. -ication, *s.* चेतनत्वारोपः, चेतनधर्मारोपः, मनुष्यगुणारोपः, उपचारः; oft. by इव, साक्षात्; 'p. of virtue' साक्षात्-मूर्तिमान्-धर्मः; *See* **Embodied.**

Personnel, *s.* कार्यकारिवर्गः.

Perspicacious, *a.* तीक्ष्ण-सूक्ष्म-दृष्टि, सूक्ष्मदर्शिन्. 2 तीक्ष्ण or सूक्ष्म-बुद्धि or मति, कुशाग्रबुद्धि. -ness, -Perspicacity, *s.* सूक्ष्मदृष्टित्वं, दृष्टिसूक्ष्मता, दृक्पाटवं. 2 सूक्ष्ममतित्वं.

Perspicuous, *a.* स्पष्ट, विशद, प्रसन्न, व्यक्त, सुप्रकाश, सुबोध. -ly, *adv.* स्पष्टं, विशदं, भिन्नार्थं. -ness, -Perspicuity, *s.* स्पष्टता, प्रसादः, वैशद्यं.

Perspire, *v. i.* प्र-,स्विद् 4 P, स्वेद-घर्म-स्रु c. -*v. t.* रोमद्वारा निःसृ c. or स्रु c., स्विद् c. -ation, *s.* स्वेदनं, घर्म-स्वेद-स्रावः. 2 स्वेदः, घर्मः, स्वेद-घर्म-जलं-बिंदुः-उदकं; 'excessive p.' प्रस्वेदः. -ing, *a.* सस्वेद, सघर्म, स्वेद-घर्म-स्राविन्, स्वेदित, स्विन्न; 'violently p' प्रस्विन्न, भृशस्विन्न.

Persuade, *v. t.* अनु-नी 1 P, प्रबुध् c., अनु-शास् 2 P, प्र-वृत् c., नियुज् 10, प्रोत्सह् c आकृष् 1 P; oft. by causal of roots 2 प्रति-इ c., प्रतीतिं-विश्वासं जन् c. (जनयति), संशयं-संदेहं-छिद् 7 P; *See* **Convince.** -ed. *a.* अनुनीत, आत्तनिश्चय-विश्वास, प्रतीत, छिन्नसंशय, आत्तप्रत्यय; 'I feel p.' इति मे प्रतीतिः, इति दृढं मन्ये. -er. *s.* प्रवर्तकः, प्रोत्साहकः, नियोजकः. -Persuasion, *s.* अनुनयः, अनुशासनं, उपदेशः, प्रवर्तनं, नियोजनं, प्रबोधः-धनं, प्रोत्साहनं. 2 संदेह-संशय-च्छेदः, शंकानिवृत्ति *f.*, दृढनिश्चयः, प्रत्ययः, निर्णयः. 3 मतं, मार्गः, पंथिन् *m.*, संप्रदायः. -Persuasive, Persuasory, *a.* सानुनय, प्रवर्तक, प्रबोधक, अनुनयिन्, हृदयग्राहिन्, आकर्षिन्. 2 प्रत्ययकारिन्, संशयच्छिद्.

Pert, *a.* चपल, लघु; *See* **Lively.** 2 धृष्ट, प्रगल्भ, अविनीत. -ly, *adv.* चापल्यात्, धृष्टतया, अविनयेन. -ness, *s.* चापल्यं, धार्ष्ट्यं, अविनयः.

Pertain, *v. i.* संबंध् pass., संबंधिन्-*a.* भू 1 P; *See* **Belong.**

Pertinacious, *a.* निर्बंधशील, आग्रहिन्, स्थिर-दृढ-प्रतिज्ञ, धीर, दृढ. -ly, *adv.* सनिर्बंधं, साग्रहं. -ness, -Pertinacity, *s.* निर्बंधः, आग्रहः, अभिनिवेशः, दार्ढ्यं, धैर्यं; *See* **Obstinate,** -cy.

Pertinent, *a.* प्रास्ताविक (की *f.*), युक्त, यथायोग्य, उपपन्न, योग्य, प्रस्तावसदृश (शी *f.*); 'to be p.' उप-पद् 4 A, युज् pass. -ly, *adv.* युक्तं, उपपन्नं, यथोचितं, प्रसंगानुरूपं, प्रस्तावसदृशं. -Petinence, -cy, *s.* युक्तता, उपपत्ति *f.*, योग्यता, प्रसंगसंगति *f.*, याथार्थ्यं, प्रस्तुतानुसारः.

Perturb, *v. t.* सं-,क्षुभ् c. आकुलीकृ 8 U, उपहन् 2 P, वि-मुह् c., व्यग्रीकृ, व्यथ् 4 A, संकरीकृ; *See* **Confuse.** -ation, *s.* सं-, क्षोभः, व्यग्रता, उपद्रवः, व्या-,मोहः, आकुलत्वं, वैक्लव्यं, उद्वेगः. -ed, *a.* क्षुब्ध, आ-व्या-कुल, विक्लव, व्यग्र, परिप्लुत, उद्विग्न, पर्याकुल.

Peruse, *v. t.* समग्रं पठ् 1 P or अधि-इ 2 A, निपुणं वच् c.; *See* **Read.** -al, *s.* अध्ययनं, पठनं, पारायणं.

Pervade, *v. t.* अभि-,व्याप् 5 P, वि-अश् 5 A, सर्वतः आक्रम् 1 U, 4 P or प्रविश् 6 P, वि-गाह् 1 A, मूर्छ् 1 P; मूर्छयन्ति विकाराः ऐश्वर्यमत्तेषु (S. 5) 'p. (the minds of) those' &c., '(the freshness of) youth has p. ed her limbs' यौवनमंगेषु संनद्धं (S.1). -ing, -Pervasive, *a.* व्यापक, व्यापिन्; 'p. all things' सर्वग, सर्वव्यापिन्; 'p. the whole body' सर्वांगीण -Pervasion, *s.* अभिव्यापनं-व्याप्ति *f.*, आक्रमणं; मूर्छनं.

Perverse, *a.* वाम, कुटिल, प्रतीप, विपरीत, प्रतिकूल, वि-प्रति-लोम, वक्र-वाम-शील, कुटिलमति, पिशुन; *See* **Obstinate.** -ly, *adv.* वामतया, कौटिल्येन, प्रतीपं, विपरीतं, वामशीलतया. -ness, *s.* प्रतीपता, वामता,

वैपरीत्यं, कौटिल्यं, कुटता, दौरात्म्यं, दुःशीलं.

Perver't, *v. t.* वि-कृ 8 U, परिवृत् c., साचीकृ, विकृ 10, विलोमीकृ, अन्यथा कृ; भ्रंश् c., विपर्यस् 4 U or c., कलुषयति (D.), कलुषीकृ; दुष् c. (दूषयति), विपरिणम् c. (णमयति). **-er, -ing**, *s.*, *a.* विकारिन्, विपरिणामिन्, विपर्यासकारिन्. **-Perversion**, *s.* विकारः, विकृति *f.*, विक्रिया, विलोमत्व, प्रतीपता, विपरिणामः, विपर्यासः, विपर्ययः, दूषणं, भ्रंसनं, साचीकरणं, कालुष्यं.

Pervious, *a.* व्याप्य, वेध्य, प्रवेश्य.

Pest, *s.* मारि-री *f.*, म(मा) रकः; (fig.) आधिः, कंटकः, उत्पातः, शल्यं; बाधः; कुलस्याधयः (S. 4) 'are a p. to the family' 'p. of the people' लोककंटकः. **-er**, *v. t.* बाध् 1 A, पीड् 10, उपद्रु 1 A, *See* **Harass.** **-ilence**, *See* (*s.*) above. **-iferous, -ilential**, *a.* मरकावह, मारात्मक, घातुक, विनाशक, दूषक, बाधक, अपकारक, अपकारिन्, अनिष्टकर (री *f.*)

Pestle, *s.* मुस(श)ल:-लं, अयोग्रं.

Pet, *s.* प्रेम-प्रीति-पात्रं, प्रेमास्पदं, क्रीडामृगः. 2 ईषत्कोपः, कोपावेशः. **-a.** प्रिय, प्रेमास्पदीभूत, वल्लभ; *See* **Favourite.** **-v. t.** लल् 10; *See* **Fondle.**

Petal, *s.* दलं, पत्रं. **-ed, -ous**, *a.* सदल, दलवत्.

Petition, *v. t.* अर्थ् 10 A, प्र-अभि°-, याच् 1 A; निविद् c., वि-ज्ञा c. (ज्ञापयति). **-s.** प्रार्थना, याच्ञा, निवेदनं, विज्ञप्ति *f.*, विज्ञापना. 2 (Written) विज्ञप्तिः, प्रार्थनानिवेदन-पत्रं. **-er**, *s.* प्रार्थकः, प्रार्थयितृ *m.*, अर्थिन् *m.*, याचकः, निवेदकः; 'ascertain who are the p. s' ज्ञायतां कः कः कार्यार्थीति (Mr. 9).

Petrify, *v. t.* पाषाणी-प्रस्तरी-कृ 8 U, कठिनीकृ, जडीकृ, संस्तंभ् c.; 'p. ed with astonishment' आश्चर्यजडीकृत. **-v. i.** पाषाणीभू 1 P. **-action**, *s.* पाषाणीकरणं; पाषाणीभूतद्रव्यं.

Petroleum, *s.* शिलातैलं-रसः.

Petrology, *s.* अश्म-विद्या or शास्त्रं.

Petticoat, *s.* शाटी, शाटकः; चंडातकं, अधोवस्त्रं (girl's); 'p. government' स्त्रीशासनं; 'under p. government' स्त्रीजितः, स्त्रीवश्यः.

Pettifogger, *s.* क्षुद्र-अधम-वृत्तिः.

Pettish, *a.* कर्कश, वक्रशील-भाव, चपलस्वभाव, प्रतीप; *See* **Peevish.** **-ly**, *adv.* कार्कश्यं, चपलं. **-ness**, *s.* कार्कश्यं, स्वभावचापलं.

Petty, *a.* लघु, क्षुद्र, अल्प; *See* **Small**; oft. by उप or कल्प in comp.; 'a p. king' उपराजा, नृपकल्पः.

Petulant, *a.* कर्कश, प्रतीप, दुःशील, वाम; *See* **Peevish.** 2 अविनीत, धृष्ट, प्रगल्भ. **-ly**, *adv.* प्रतीपं, धृष्टवत्. **-Petulance**, *s.* प्रतीपता, दुःशीलं, धृष्टता.

Pewit, *s.* *See* **Lapwing.**

Pewter, *s.* कांस्यं, पीतलोहं. **-er**, *s.* कांस्यकारः.

Phalanx, *s.* व्यूहः; पंक्ति *f*

Phantasm, *s.* आ-,भासः, छाया, माया मनोरथसृष्टि *f.*

Phantasmagoria, *s.* मायाजालं.

Phantasy, *s.* *See* **Fancy.**

Phantom, *s.* भूतः, वेतालः, पिशाचः, रात्रिचरः. 2 आ-,भासः, मनोरथसृष्टि *f.*, माया, कल्पना.

Pharisee, **Pharisaic**, *s.*; *a.* *See* **Hypocrite.**

Pharmacopœia, *s.* औषधसंस्कारशास्त्रं, भेषजसंस्कारग्रंथः.

Pharmacy, *s.* औषधक्रिया-संस्कारः-विद्या.

Pharos, *s.* दीपस्थानं-गृहं.

Phase, Phasis, *s.* दर्शनं, वस्तु *n.*; 'p. s of the moon' चंद्रस्य क्षयवृद्धी. 2 (Point of view) दृष्टि *f.*; *See* **View.**

Pheasant, *s.* चकोरः, जीवंजीवः.

Phenomenon, *s.* दृग्विषयः, गोचरवस्तु *n.*, दर्शनं, आलोकः. 2 उत्पातः, अद्भुतं.

Phial, *s.* लघुकूपी, काचकूपी-पात्रं.

Philander, *v. i.* स्त्रीजनसमागमं अभ्यस् 4 P, वि-लस् 1 P, विलासं-विभ्रमं-कृ c.

Philanthropy, *s.* लोकहितेच्छा, लोक-जन-प्रीति *f.*, सर्वभूतदया, विश्वप्रीतिः, विश्वसौहृदं. **-ic-, ical**, *a.* लोकहितैषिन्, जनहितकामः, जगन्मित्रं, विश्वमित्रं, विश्वसुहृद्. **-ist**, जनहितैषिन् *m.* वि-श्वसुहृद्.

Philippic, *s.* भर्त्सनवाक्यं, निंदात्मकः प्रबंधः.

Philology, *s.* भाषाविज्ञानं-तत्त्वं, शब्दव्युत्पत्तिशास्त्रं-विद्या. **-er-, -ist**, *s.* शाब्दिकः भाषातत्त्वज्ञः. **-ical**, *a.* शाब्दिक (की *f.*), शब्दशास्त्रीय.

Philomath, *s.* विद्याप्रियः-भक्तः-अभ्यासेविन् *m.* **-y**, *s.* विद्यासेवनं.

Philosophy, *s.* दर्शनं; 'six systems of p.' षड्दर्शनं. 2 तत्त्वज्ञानं, विज्ञानं, तत्त्वविद्या-शास्त्रं, तत्त्वं, ज्ञानं, विद्या, शास्त्रं in comp.; 'moral p.' नीतिशास्त्रं, 'logical p.' तर्कशास्त्र-विद्या, &c. **-er**, *s.* दर्शनज्ञः, तत्त्ववित् *m.*, तत्त्वज्ञः-ज्ञानिन् *m.* तार्किकः, ज्ञानी, पंडितः, प्राज्ञः, ज्ञानविदः; 'p.'s stone' चिंतामणिः; स्पर्शमणिः. **-ic, -ical**, *a.* तत्त्व-दर्शन in comp.; दार्शनिक (की *f.*). 2 विज्ञ, तत्त्व-

ज्ञानपर, ज्ञान-विद्या-पर. -ically, *adv.* दृष्टीनानुसारेण, तत्त्वतः. -ize, *v. i.* तत्त्वं निरूप् 10 or आलोच् 10 or अन्वीक्ष् 1 A.

Philtre, *s.* मंत्रौषधं, वशीकरणचूर्णं.

Phiz, *s.* *See* **Face.**

Phlebotomy, *s.* शिरावेधः-मोक्षः-छेदः. रक्तमोक्षणं-स्रावः

Phlegm, *s.* कफः, श्लेष्मन् *m.*, सिंघाणकं. 2 मांद्यं, जाडयं; 'a medicine removing p.' (phlegmagogue) श्लेष्महरं, कफनाशनं. -atic, *a.* कफिन्, श्लेष्मल-ण, बहुकफ. 2 कफकर (री *f.*), श्लेष्मजनन (नी *f.*). 3 श्लेष्मज. 4 जड, मंद, शीत; *See* **Indifferent.**

Phonetic, *a.* स्वरसंवादिन्, ध्वनि-स्वर-in comp. -**Phonetics, Phonics,** *s.* स्वर or ध्वनि-विद्या or शास्त्रं.

Phonograph, *s.* स्वरलेखनयंत्रं.

Photograph, *s.* आलोकलेख्यं. -er, *s.* आलोकलेख्यकारः.

Phrase, *s.* वाक्यं, उक्ति *f.*, वचनं. -*v. t.* अभि-धा 3 U, उद्दिश् 6 P; *See* **Call.** -**Phraseology,** *s.* वाक्यबंधः-रचना, भाषासरणि *f.*, वाक्प्रकारः, वाग्रीति *f.*-व्यापारः-व्यवहारः; 'dramatic p.' नाट्योक्तिः, नाट्यपरिभाषा.

Phrenetic, *a.* उन्मत्त; *See* **Frantic.** -**Phrenitis,** *s.* सन्निपातज्वरः, उन्मादः; *See* **Frenzy.**

Phrenology, *s.* मस्तिष्कविद्या.

Phthisic, Phthisis, *s.* श्वासावरोधः, श्वासाकृच्छ्रं; क्षयः, क्षयरोगः, शोषः, यक्ष्मन् *m.*, राजयक्ष्मन्. -**Phthisical,** *a.* क्षयिन्, क्षयरोगिन्.

Phylactery, *s.* रक्षाकरंडः.

Physic, *s.* चिकित्सा, उपचारः, वैद्यक्रिया, औषधोपचारः. 2 औषधं, भेषजं, अगदः. -*v. t.* कित् desid. (चिकित्सति-ते), उपचर् 1 P. भेषजं दा 3 U. -ian, *s.* वैद्यः, भिषज् *m.*, चिकित्सकः, अगदंकारः, रोगहारिन्-हृत् *m.* -**Physical,** *a.* साकार, स्थूल, जड; *See* **Material.** 2 अंग, विग्रह, शरीर in comp.; 'p. strength' शरीरबलं; 'p. substance' स्थूलद्रव्यं-वस्तु. 3 **Medicinal,** q. v.; 'p. science (physics)' पदार्थविज्ञानं,-शास्त्रं. -ly, *adv.* प्रकृत्या, स्वभावतः, जातितः, जन्मतः; *See* **Naturally.**

Physiognomy, *s.* आकृति *f.*, वदनाकृतिः. मुखं, वदनं. 2 वदनलक्षणनिरूपणं. -ist, *s.* मुखसामुद्रिकः

Physiography, *s.* भूवर्णनं.

Physiology, *s.* प्राण्योषधिजीवनशास्त्रं.

Physique, *s.* शरीरस्थिति *f.*

Piacular, *a.* अघ-पाप-नाशिन्.

Picaroon, *s.* समुद्रीयदस्युः.

Pick, *v. t.* चि 5 U, ग्रह् 9 U, समाहृ 1 P, आ-दा 3 A, उद्-धृ 1 P, 10, लू 9 U, छिद् 7 P, (flower &c.), 2 क्षुद् c., शुच् 2 P or c., परिष्कृ 8 U. 3 (Up) वृ 5 U, उद्धृ 1 P, उद्ग्रह्, पृथक् कृ; 'p. a bone' अस्थिमांसं चर्व् 1 P, 10; 'p. out' उत्पट् 10, निष्कृष् 1 P; 'p. a quarrel' कलहं उत्-स्था c. (उत्थापयति); 'p. holes' (in another's coat) परस्य छिद्राणि दृश् 1 P, रंध्राणि-छिद्राणि-अन्विष् 4 P; 'p. the pocket' ग्रंथिं छित्वा अपहृ. -*s.* **Pick-axe,** q. v. 2 उद्धारः, चयनं. 3 विशिष्टभागः, उत्कृष्टभागः; 'ear-p.' कंडूयनकं; 'tooth-p.' दंतोल्लेखनी; 'p.-axe' टंकः, पाषाणभेदनी, पाषाणदारणः; 'p.-pocket' ग्रंथिच्छेदकः-चौरः. -ing, *s.* उद्धरणं, उद्ग्रहणं.

Picket, *s.* सेनारक्षः, रक्षकदलं. 2 शंकुः, स्थाणुः.

Pickle, *s.* संधितं, संधानं, संधितद्रव्यं. 2 लवणं. -*v. t.* सं-धा 3 U, उपस्कृ 8 U.

Picnic, *s.* विहरणं, वनभोजनं.

Pictorial, *a.* सचित्र, चित्रोपेत, चित्रलिखित.

Picture, *s.* चित्रं, आलेख्यं, प्रतिमा, प्रतिकृति *f.*, प्रतिरूपं, प्रतिच्छंदः-दकं, प्रतिच्छाया; 'as if drawn in a p.' आलिखित इव; 'p.-board' चित्रफलकः; 'p.-frame' चित्राधारः, चित्रावरणं; 'p.-gallery' चित्रावली, चित्रशाला; 'p.-maker' चित्रक(का)रः. -*v. t.* मनसि कृ 8 U, आलोच् 10, मनसा क्लृप् c. or विचर् c. or वि-भू c. 2 चित्र् 10, आलिख् 6 P, वर्ण् 10. -ed, *a.* चित्रगत, आलेख्यगत, चित्रार्पित, आलिखित. 2 मनसा कल्पित. -**Picturesque,** *a.* चित्रोपम, चि-,चित्र, शबल.

Piebald, *a.* *See* **Variegated.**

Piece, *s.* खंडः-डं, विभागः; अंशः, लवः, शकलः-लं, वि-,दलं, भित्तं. 2 रचना, प्र-,बंधः; 'to break in p s' शकलीकृ 8 U, खंडशः कृ, खंड् 10; 'to fall to p. s' वि-,दल् 1 P; 'p. of poetry' काव्यप्रबंधः, कविता; 'p. of work' कार्यं; 'p. of money' मुद्रा; p. of water' जलाधारः, जलाशयः; 'in p. s' खंडशः, लवशः; 'p. at chess' शा (सा)रिः-रः; 'a p. to each' एकैकं, प्रत्येकं, पृथक् पृथक्; 'what a p. of work is man' अहो निर्माणविशेषः नरजीवः; 'of a p.' एकरूप-प्रकार; 'of a p. with' सदृश (शी *f.*), अनुरूप; *See* **Like.** -*v. t.* संयुज् 7 U, 10, संधा- समाधा-3 U. -less, *a.* अखंड. -**Piecemeal,** *adv.* खंडशः लवशः, भागशः, खंडं खंडं, पृथक् पृथक्. -*a* भागिन्, खंड in comp.

Pied, *a.* *See.* **Variegated.**

Pier, *s.* सेतुबंधः 2 स्तंभः, वप्रः-प्रं.

Pierce, *v. t.* व्यध् 4 P, भिद्-भिंद् 7 P, प्र-भंज् 7 P, छिद् 7 P; *See* **Perforate. 2** आ-उप-हन् 2 U, शीतवातोपहतः 'p. ed by cold winds'. **-ed**, *a.* विद्ध, निर्भिन्न, छिद्रित; 'p. ed through the heart' भिन्नहृदय; 'having the ears p.' विद्ध-छिद्रित-कर्ण. **-er**, *s.* वेधकः. भेदकः. **2** वेधनिका, वेधनी. **-ing**, *a.* वेधक; वेधिन्, भेदिन्, भिद्-छिद् in comp.; 'p. the vital parts of the heart' हृदयमर्मभिद्-छिद्; (sound) परुष, कर्कश. **-s.** वेधः-धनं, निर्भेदः, छेदः-दनं.

Piety, *s. See* under **Pious.**

Pig, *s.* शूकरशावः-वकः शूकरः; *See* **Hog. 2** कुशी, लोहपिंडः; 'p.-iron' असंस्कृतं अयः; 'p.-headed' स्थूल, स्थूलधी. **-gish**, *a.* शूकरोपम.**-Piggery**, *s.* शूकरालयः.

Pigeon, *s.* कपोतः, पारावतः, कलरवः; 'wood p.' हारि(री)तः; 'p.-hearted' भीरुहृदय, कातर; 'p.-hole' कपोतबिलं; 'p.-house,-cot' कपोतपालिका, विटंकः.

Pigment, *s.* वर्णकः; वर्णः, रंगः.

Pigmy, *s.* वामनः, ह्रस्वः, खर्वः. **-a.** वामन, ह्रस्व, खर्व, लघुतनु, अल्पमूर्ति.

Pike, *s.* प्रासः, कुंतः, शूलः-लं; *See* **Lance;** 'p.-man' प्रासिकः, कौंतिकः, शाक्तीकः, शूलिन् *m.*

Pilaster, *s.* चतुरस्रः स्तंभः.

Pile, *s.* राशिः, चयः, निकरः, पुंजः, पूगः, स्तोमः, समूहः. **2** चिता, चिति *f.*, चित्या. **3** स्थूणा, स्तंभः, शंकुः, कीलः. **4** हर्म्यं, भवनं, महामंदिरं. **5** ऊर्णा. **-v. t.** समाचि 5 U, राशीकृ 8 U.

Piles, *s.* अर्शस् *n.*, दुर्नामकं, अर्शोरोगः, गुदकीलकः, गुदांकुरः; 'affected by p.' अर्शस.

Pilfer, *v. t.* मुष् 9 P, चुर् 10, अपहृ 1 P **-er**, *s.* चौरः, मोषकः; *See* **rob,-ber.**

Pilgrim, *s.* यात्रिकः, तीर्थसेविन् *m.* **-age**, *s.* तीर्थयात्रा, यात्रा, यात्राप्रसंगः, तीर्थाटनं-सेवा; 'on a p. to Garuda' गरुडस्य यात्राप्रसंगेन; 'place of p.' तीर्थः-र्थं, पुण्यस्थानं.

Pill, *s.* वटिका, गुटिका, गुलिका.

Pillage, **-v. t.** वि-लुंठ्-ट् 1 P, 10, अपहृ 1 P. **-s.** विलुंठनं, लोप्त्रं, लोत्रं, अपहारः. **-er**, *s.* लुंठकः, अपहारकः.

Pillar, *s.* स्तंभः, स्थाणुः, स्थूणा, अवष्टंभः; यूपः (sacrificial); 'p. of state' राज्यस्य आधारस्तंभः; 'p. s of justice' न्यायाधाराः, धर्मावष्टंभाः.

Pillow, *s.* उपधानं, उपबर्हः, बालिशः; 'p.-case' उपधानकोशः-आवेष्टनं; 'I slept, making my left arm serve as a p.' वामभुजमुपधाय अशयिषि (D. K. II. 5). **-v. t.** उपधा 3 U, उपधानीकृ 8 U.

Pilous, *a.* लोमश, प्रचुरलोमन्. **-Pilosity**, *s.* लोमशत्वं, लोमप्राचुर्यं.

Pilot, *s.* कर्णधारः-ग्राहः, कर्णिकः, कर्णिन् *m.*, नाविकः, नौवाहः **2 Guide**, q. v. **-v. t.** मार्गं दृश् c., प्रणी 1 P, वह् c. **-age**, *s.* कर्णिकवेतनं.

Pimp, *s.* विटः, संचारकः; *See* **Pander.**

Pimple, *s.* पिटिका, स्फोटः, क्षुद्र-लघु-व्रणः. रक्तस्फोटः- गंडः, रक्तवटी. **-ed,-y**, *a.* सस्फोट, व्रणिन्, सव्रण, पिटिकावृत.

Pin, *s.* सूचि *f.*, कीलः-लकः-कं, शलाका, शंकुः, शल्यं **2** (Of a carriage) अणिः-णी, अक्षाग्रकीलः; 'p.-maker' सूचिकारः. **-v. t.** सूच्या बंध् 9 P, कील् 10.

Pincers, *s.* संदंशः-शकः, कंकमुखं.

Pinch, *v. t.* पीड् 10, बाध् 1 A, क्लिश् 9 P, संकुच् 1 P (the body), आर्तीकृ 8 U; 'p. ed with cold' शीतार्त, हिमपीडित; 'p. ing poverty' दुःसहं दारिद्र्यं. **2** अंगुल्यग्रेण पीड्. **3** मुष्टिना संग्रह् 9 P, संग्रह्; 'none but the wearer knows where the shoe p. es' न हि वंध्या विजानाति गुर्वीं प्रसववेदनां. **-s.** अंगुलिपीडनं, संग्रहः, ग्रहणं; 'p. of snuff' नस्यकूर्चः. **2** संकटावस्था, दुर्गति *f.*, कष्टं, कृच्छ्रं; 'p.-fist' बद्ध-दृढ-मुष्टिः, असुक्तहस्तः.

Pine, *s.* देवदारुः-रु, पीतद्रुः, सरलः, पूतिकाष्ठं; *See* **Fir** also. **-v. i.** (Away) अवसद् 1 P, परि-,म्लै-म्ले 1 P, क्षि-pass., क्षिप्-क्षी 4 A. **2** (For) उत्सम् 4 P, उत्कंठ् 1 A, उत्सुकायते (D.); oft by उत्क, उत्सुक, उत्कंठ in comp.; 'a heart p. ing away in absence' विरहोत्कंठं हृदयं; 'p. ed for his home' गृहं मंतुमुद्यताम्यत्, अविप्लुतासमागमोत्कः (K. vi. 95) 'p. ing to be united with Parvati'; अंतःपुरविरहपर्युत्सुकस्य राजर्षेः (S. 3) 'who is p. ing by separation &c. **-ing**, *s.* म्लानि *f.*, अवसादः, उत्कंठा. **-a.** म्लान, क्षीण, विषण्ण, उत्क, उत्सुक, सोत्कंठ.

Pinion, *s.* पक्षः, पर्णं **2** बाहुपाशः-बंधः. **-v. t.** पक्षौ बंध् 9 P, बाहू बंध्.

Pink, *s.* पाटलवर्णः, पाटलः. **2** अग्रं, शिखरं, पराकाष्ठा. **-a.** पाटल, पाटलवर्ण; 'p.-eyed' गज-सूक्ष्म-नेत्र. **-v. t.** व्यध् 4 P; *See* **Perforate.**

Pinnace, *s.* क्षुद्र-लघु-नौका.

Pinnacle, *s.* अट्टः, प्रासादशृंगं, प्रोच्छ्रितं हर्म्यं. **2** शिखरं, शृंगं, अग्रं.

Pioneer, *s.* आटविकः, काष्ठ-तरु-छिद् *m.* **2** मार्गदर्शकः, अग्रेसरः, अग्रयायिन् *m.* *See* **Forerunner.** **-v. t.** सैन्यमार्गं शुध् c.

Pious, *a.* धार्मिक (की *f.*), पुण्य-धर्म-शील, धर्मात्मन्, पुण्य, पुण्यात्मन्, भक्तिमत्, शुचि-

व्रत, भक्ति or धर्म-निष्ठ or परायण, धर्माचार; 'led a p. life' धर्माचरणेन आयुरक्षपयत्; 'p. action' धर्मक्रिया; 'for p. purpose' धर्मार्थं. 2 धर्म-भक्ति-मूलक. -ly, *adv.* भक्त्या, धार्मिकवत्. -ness,-**Piety**, *s.* धर्मनिष्ठा-परता-आसक्ति *f.*, धर्मात्मता, पुण्यशीलं, ईश्वर-धर्म-भक्ति *f.*, ईश्वरनिष्ठा-सेवा, पुण्यता, भक्तिः; 'distinguished for p.' धर्मप्रधान. 2 पितृसेवा, पुत्रधर्मः. [चि-क 2 P.

Pip, *s.* बीजं. 2 बिंदुः, अंकः. -*v. i.* कूज् 1 P,

Pipe, *s.* वंशः, वेणुः, सुषिरं. 2 नालः, नाडि-डी-लि-ली *f.*, प्रणालः-ली; 'water-p.' सारणि *f.*, प्रणालिका. -*v. i.* वेणुं वद् c. or ध्मा 1 P. -er, *s.* वांशिकः, वेणुध्मः. [illegible]

Piquant, *a.* उग्र, तिग्म, कटु, तीक्ष्ण, [illegible]. 2 मिष्ट, स्वादु, सरस.

Pique, *s.* कलिः, कलहः; ईषत्कोपः. -*v. t.* ईषत् कुप् c. or रुष् c. 2 उत्तिज् c., उत्सह् c., प्रोत्सह् c., प्र-वृत् c. 3 (Oneself) अभिमन् 4 A; विकत्थ् 1 A; 'he p.s himself upon his learning' पंडितंमन्योऽसौ.

Pirate, *s.* समुद्रदस्युः. 2 साहसिकनौका. 3 शब्दचौरः. -*v. t.* अपहृ 1 P, लुंठ्-हृ 1 P, 10. **Piracy**, *s.* समुद्रीयचौर्यं-लुंठनं -**Piratical**, *a.* साहसिन्, साहसिक (की *f.*).

Piscator, *s.* *See* **Fisherman.**

Pisces, *s.* मीनः, मीनराशिः.

Piscivorous, *a.* मत्स्याशन, मत्स्याद.

Pismire, *s.* *See* **Ant.**

Piss, *s.* मूत्रं, मेहः. -*v. t.* मूत्रं उत्सृज् c., मिह् 1 P, मूत्र् 10.

Pistil, *s.* गर्भकेसरः-रं.

Pit, *s.* गर्तः-र्ता, विवरं, बिलं, अवटः; 'p.-coal' आकरांगारः; 'p.-fall' गूढ or छन्न-कूपः or गर्तः, अंधकूपः. -*v. t.* सूक्ष्मगर्तैः अंक् 10 or चिह्नयति (D.). 2 योद्धुं प्रोत्सह् c., प्रविशुध् c.

Pitch, *v. t.* रच् 10, प्रतिवि-धा 3 U; रुह् c. (रोपयति), स्था c. (स्थापयति), निविश् c. 2 क्षिप् 6 P, प्र-,अस् 4 P, नि-,पत् c. 3 अरालेन अंज् 7 P. -*v. i.* आ-अव-पत् 1 P, अवरुह् 1 P, अव-तृ 1 P, अध्यास् 2 A. 2 निविश् 6 A, शिबिरं अध्यास्. 3 अधोमुखेन पत्, अवाक् गम् 1 P. 4 (Upon) वृ 5 U; *See* **Choose.** -*s.* तिंदुः, रालः, अरालः, यक्षधूपः सर्जरसः, सर्वरसः, बहुरूपः 2 कोटि *f.*, काष्ठा, अग्रं, शिखरं; 'highest p.' परा काष्ठा-कोटिः. 3 परिमाणं, पर्यंतः; *See* **Degree.** 4 उत्संगः, कटकः-कं. 5 स्वरः; 'mineral p.' शिलाजतु *n.* -y, *a.* तिंदुलिप्त. 2 सूचिभेद्य, अंध, अतिकृष्ण.

Pitcher, *s.* कुंभः, घटः, घटी, कलसः-शः, पुटग्रीवः; *See* **Jar.**

Pith, *s.* मज्जा, गर्भः, सारः. 2 सारः, सारांशः, सत्त्वं, तत्त्वं. 3 निर्यासः, रसः. 4 सत्त्वं, वीर्यं, बलं, उत्साहः. -less, *a.* असार, निःसार, फल्गु, निःसत्त्व, विरस. -y, *a.* ससार, सत्त्वपूर्ण, सरस, ससत्त्व, सारवत्, सारगर्भ. 2 सप्रभाव, तेजस्विन्, वीर्यवत्, ससत्त्व.

Pittance, *s.* स्तोकांशः, अल्पस्वभागः; अल्पमूल्यं-वेतनं, ग्रासाच्छादनमात्रं.

Pity, *s.* दया, अनुकंपा, करुणा, घृणा, कृपा, अनुक्रोशः; 'in p. to my passion' (राजन्नर्थितं) दुःखं मे निरवेक्ष्य (Mr. 5); 'what a p. it is' अहो नु कष्टमेतत्. -*v. t.* 'take p. on' दय् 1 A (with gen.); अनुकंप् 1 A, दयां कृ 8 U (with loc.); प्रसद् 1 P. -**Piteous, Pitiable**, *a.* अनुकंप्य, करुणा-अनुकंपा-योग्य, दयाविषयः-भाजनं-पात्रं, करुण, दीन; 'in p. accents' करुणस्वनैः. 2 वराक (की *f.*), तपस्विन् (of persons). -ly, *adv.* करुणं, दीनं. -ness, *s.* अनुकंप्यता, कारुण्यं, दैन्यं. -**Pitiful, -Pitying**, *a.* करुणार्द्र, करुणामय (यी *f.*), करुणा-दया-शील, सदय, सानुकंप, दयालु, कृपालु; *See* **Kind**; 'a p. person' दयानिधिः-सागरः, दीनबंधुः-वत्सलः. 2 करुण, दीन, शोच्य 3 **Contemptible.** q. v. -ly, *adv.* सदयं, सानुकंपं, सकरुणं. -ness, *s.* दयालुता, कारुण्य, दयार्द्रता. -**Pitiless**, *a.* निर्दय, निरनुक्रोश, निर्घृण, निष्कृप, क्रूर, निष्ठुर, कठोर, अकरुण. -ly, *adv.* निर्दयं, क्रूर निष्ठुरं.

Pivot, *s.* विवर्तनकीलः.

Placard, *s.* घोषणापत्रं. -*v. t.* घोषणापत्रेण प्रकाश् c.

Placate, *v. t.* **Appease**, q. v. -**Placable**, *a.* क्षमाशील, सांत्वनीय, आराध्य, प्रसाद्य.

Place, *s.* स्थानं, स्थलं, प्र-,देशः, स्थली, भू-भूमि *f.*, धिष्ण्यं. 2 पदं, आस्पदं, विषयः. 3 पदं, पद्धति-ती *f.*, अधिकारः, नियोगः, अधिकारपदं; *See* **Office.** 4 अवकाशः, अवसरः, प्रसरः; 'p. of honour' संमानपदं, गौरवपदं; 'in one p.' एकत्र; 'in many p.s' बहुत्र; 'p. of residence' निवासस्थानं; वसति *f.*; 'p. for dancing' नृत्यशाला-स्थानं; 'out of p.' अस्थाने, अनुचितं; 'in the p. of a father' पितृस्थाने-भूमौ; 'p. for fear' भयस्थानं-कारणं-हेतुः; 'in one p.-in another p.' क्वचित्-क्वचित्, इतः-इतः, एकत्र-अन्यत्र; 'in the first p.' प्रथमं, प्रथमतः, प्रथमं तावत्; 'in the next p.' अपरंच, पुनः, पुनश्च; 'to give p.' स्थानं त्यज् 1 P, व्यप-सृप् 1 P, अप-सृ 1 P; 'to take p.' *See* **Happen, Occur.** -*v. t.* स्था c. (स्थापयति), धा 3 U, नि-आ°-, वि-,न्यस् 4 U, निक्षिप् 6 P, आ-नि-विश् c., आरुह् c. (रोपयति), धृ 10; oft. by कृ 8 U, दा 3 U, व्याप् c., (व्या-

धारयामास करं किरीटे R. vi. 19); 'p. over' अधिकृ, अधि-ष्ठा 1 P; 'p. in an office' पदे नियुज् 7 A, 10 or आरुह् c.

Placid, *s.* शांत, प्र-उप°-, प्रसन्न, निराकुल, अनुद्विग्न, जितक्रोध, असंभ्रम, शांतात्मन्, प्रसन्नचित्त. **-ly,** *adv.* प्रसन्नं, शांत्या, शांतचेतसा, निराकुलं. **-ity, -ness,** *s.* शमः, शांति *f.*, प्रसादः, अक्रोधः, असंभ्रमः, अक्षोभः.

Plagiarism, *s.* शब्दचौर्यं, वाक्यहारः. **Plagiarist,** *s.* शब्द-ग्रंथ-चोरः.

Plague, *s.* मारी, महामारी, म(मा)रकः. 2 उत्पातः, अरिष्टं, अनर्थः, शल्यं, उपद्रवः, कंटकः, उपप्लवः; *See* **Pest.** *-v. t.* मार्या ग्रस् 1 A or आक्रम् 1 U, 4 P. 2 बाध् 1 A, पीड् 10, तप् c., दु 5 P; *See* **Harass.** **-ing,** *a.* बाधक, पीडक, क्लेशद, पीडाप्रद.

Plain, *s.* समभूमि *f.*-देशः-स्थलं-ली, समभूभागः; *See* **Level.** *-a.* सम, सपाट. 2 विनीत, निरलंकार, अभूषित, निर्भूषण. 3 स्पष्ट, व्यक्त, विशद, परि-,स्फुट, सुबोध, स्पष्टार्थ, भिन्नार्थ, प्रकाश, प्रत्यक्ष, प्रकट. 4 केवल, मात्र in comp. 5 (Style) अनलंकृत, शुद्ध, अनलंकार, अव्यंजन. 6 (Food) उपस्कारहीन-शून्य, असंस्कृत. 7 अमाय, दक्षिण, निष्कपट, निर्व्याज, सरल, कपट-माया-हीन, निर्व्यलीक, अकृत्रिम, ऋजु; *See* **Frank.** 8 सामान्य, साधारण (णी *f.*); मध्यमरूप, नातिसुंदर (री *f.*); 'a p. woman' 'one p. in person' सामान्यलावण्योपपन्ना, नातिसुभगा, अनतिसुंदरी; 'p. dealing' न्यायाचार, शुद्ध-सरल-मति, निर्व्यलीक, दक्षिण, अमाय, ऋजु; (*s.*) सारल्यं, निष्कापट्यं. *-v. t.* समीकृ 8 U. **-ly,** *adv.* स्पष्टं, व्यक्तं, स्फुटं, स्पष्टार्थं, सुबोधं, प्रकाशं, प्रकटं, प्रत्यक्षं. 2 निर्व्याजं, निर्व्यलीकं, अवक्रं, सारल्येन, अमायया, निष्कपटं. 3 विनीतं, अनलंकारं; 'p. dressed' विनीतवेष. **-ness,** *s.* समता, विनीतत्वं, भूषणाभावः, व्यक्तता, स्पष्टता, वैशद्यं, सुबोधता, प्राकाश्यं, अव्याजः, निर्व्याजता, अकापट्यं, सारल्यं, अमाया, आर्जवं, &c.

Plaint, *s.* प्रतिज्ञा, अभियोगः, भाषापादः, भाषा, पूर्वपक्षः, पक्षः. 2 विलापः, विलपनं, परिदेवनं-ना, शोकः. **-Plaintiff,** *s.* अर्थिन् *m.*, वादी, अभियोगी, कार्यार्थी, अभियोक्तृ *m.*, सूचकः. **-Plaintive,** *a.* परिदेविन्, विलापिन्. 2 शोकावह, शोकार्थक, शोक-दुःख-गर्भ, करुण, दीन, सकरुण; 'in p. words' परिदेविताक्षरैः. **-ly,** *adv.* करुणं, दीनं.

Plait, *s* भंगि-गी *f.*, भंग, ऊर्मि *f.*, पुटः, चूडः. 2 वेणि-णी *f.*, कबरी, धम्मिल्लः. *-v. t.* ग्रंथ् 9 P, व्या-वृत् c., पुटीकृ 8 U, संवे 1 P, वेणीकृ, वेणीरूपेण ग्रंथ्.

Plan, *s.* उपायः, प्रयोगः, प्र-,युक्ति *f.*, कल्पना. 2 सूत्रपातः, चित्रलेखनं, आलेख्यं, स्थूलवर्णनं. *-v. t.* प्र-सं-क्लृप् c., प्र-,युज् 10, चिंत् 10, मंत्र् 10 A, अनुसंधा 3 U, आलोच् 10, मनसा विचार् c. or वि-मृ c. 2 आलिख् 6 P, सूत्रपातं कृ 8 U. **-ning,** *s.* उपाय-कल्पना-योजना.

Planch, *See* **Plank.**

Plane, *a.* सम, समस्थ. *-s.* समं, समभागं, धरातलं. 2 तक्षणी, त्वक्षणी. *-v. t.* समीकृ 8 U. 2 तक्ष् 1, 5 P.

Planet, *s.* ग्रहः, ज्योतिस् *n.*; 'minor p.' उपग्रहः; 'passage of a p.' संक्रमः, संक्रांति *f.*; 'aspect of a p.' ग्रहदृष्टि; 'influence of a p.' ग्रहावेशः. **-ary,** *a.* ग्रह in comp.

Planish, *v. t.* समीकृ 8 U., तिज् c., प्र-मृज् c.

Plank, *s.* फलकः-कं; दारु-काष्ठ-फलकः. *-v. t.* फलकैः आस्तॄ 9 U or आच्छद् 10.

Plant, *s.* ओषधि *f.*, लता; तरुः, वृक्षः. *-v. t.* (Seeds) आ-,रुह् c. 2 प्रति-,स्था c. (स्थापयति), वि-,न्यस् 4 U, निविश् c., नि-खन् 1 P, नि-धा 3 U, रुह् c. 3 अधि-,वस् c. **-ation,** *s.* रोपणं. 2 क्षेत्रं, in comp., वाटः-टी, वाटिका; शाकटं-शाकिनं in comp., वृक्षवाटिका; 'sugar-p.' इक्षुशाकटं-वाटिका. 3 **Colony,** q. v. **-er,** *s.* रोपयितृ *m.*, रोपकः. 2 वाटिकेश्वरः.

Plantain, *s.* कदली-लः, रंभा, वारणबुसा-षा, मोचा, अंशुमत्फला, काष्ठीला; 'p. fruit' कदलीफलं, मोचं; 'wild p.' काष्ठकदली.

Plantigrade, *a.* पादतलचारिन्.

Plash, *s.* आघातः, आस्फालनं. 2 क्षुद्रपल्वलः. *-v. i.* जले क्रीड् 1 P, जलं आस्फल् c. *-v. t.* अवच्छिद् 7 P, लू 9 U, कृत् 6 P. 2 संग्रंथ् 9 P. **-y,** *a.* जलाढ्य.

Plaster, *s.* लेपः, सुधा, चूर्णलेपः. 2 व्रणप्रलेपः, उपदेहः. *-v. t.* लिप् 6 P, वि-अनु-प्र-°, दिह् 2 U, उप-नह् 4 P. **-er,** *s.* लेपकः, पलगंडः. **-ing,** *s.* वि-प्र-लेपः-पनं.

Plastic, *a.* आकारद, कल्पक. 2 नम्य, सुनम्य.

Plat, *s.* **Plot,** q. v. *-v. t.* **Weave,** q. v. 2 प्र-सं-क्लृप् c., चिंत् 10.

Plate, *s.* पात्रं, भाजनं. 2 कोशः-षः, हेमकोशः. 3 फलकः-कं, पत्रं; पट्टः-ट्टं, पट्टिका; 'copper p.' ताम्रपट्टः, ताम्रपत्रं; 'p. s of grant' शासन-नियम-पत्राणि. *-v. t.* रजतपत्रेण आवृ 5 U or आच्छद् 10; रजतेन अलंकृ 8 U. **-ed,** *a.* रजतपत्रावृत, रूप्यनिबद्ध.

Plateau, *s.* समस्थली, अधित्यका, *See* **Level.**

Platform, *s.* वेदि *f.*, वेदिका, उच्चस्थानं.

Platoon, *s.* गुल्मः-ल्मं.

Platter, *s.* पात्रं, भाजनं.

Plaudit, *s.* प्रशंसा, धन्यवादः, जयघोषः.

Plausible, *a.* सत्याभास, सत्यसंकाश, बाह्यतः रमणीय.

Play, *v. i.* क्रीड् 1 P, रम् 1 A, वि-हृ 1 P, विलस् 1 P, खेल् 1 P. 2 (At dice) दिव् 4 P, क्रीड्, ग्लह् 1 A; 'p. s at dice' अक्षैः -अक्षान्-दीव्यति. 3 वद् c. (instrument). 4 वेप् 1 A, चुल् 1 A, चल् 1 P. —*v. t.* रूप् 10, वह् 10, अभिनी 1 P, ex. by denom.; 'p. s the king' नृपायते; 'p. s the woman' स्त्री-वाचरति. 2 प्र-,चल्-इ c., प्रवृत् c., प्रसृ c. 3 वि-धा 3 U, कृ 8 U, अनु-ष्ठा 1 P. —*s.* क्रीडा, खेला-लनं, लीला, केलि *f.*, विनोदः, विलासः, विहारः, कौतुकं, परिहासः; 'in p.' लीलया, परिहासेन. 2 नाटकं. 3 अक्षक्रीडा, द्यूतं, देवनं. 4 अभिनयः, गति *f.* 5 आचरणं, चेष्टितं; वृत्ति *f.*, व्यापारः, कृत्यं, चेष्टा; 'foul p.' दुश्चेष्टितं. 6 चलनं, सरणं. 7 प्रसरः, अवकाशः, अवसरः; 'p.-day' अनध्यायदिवसः-तिथिः, विश्रामदिवसः; 'p. house' नाटक-रंग-शाला; 'p.-thing' क्रीडनकं, क्रीडाद्रव्यं-वस्तु. —**er,** *s.* क्रीडकः; (at dice) अक्ष-,देविन् *m.*, अक्षक्रीडकः, अक्षधूर्तः. 2नटः, कुशीलवः, नर्तकः, अभिनेतृ *m.* पात्रं. —**ful,** *a.* क्रीडासक्त,क्रीडापर-मग्न,केलि-क्रीडा-लीला-शील,लीला-खेला-पर, विलासिन्, विनोदिन्; (of things) सलील -क्रीडा-केलि in comp.; 'p. anger' प्रणयक्रीडा-कोपः, केलिकोपः. —**fully,** *adv* क्रीडापूर्वं, परि-हासेन (jokingly); लीलया, सकौतुकं, सविलासं, सखेलं. —**fulness,** *s.* क्रीडासक्ति *f.*, लीलापरता, सलीलत्वं, क्रीडाशीलता.

Plea, *s.* कारणोत्तरं, उत्तरं, उत्तरपादः. 2 व्यपदेशः, छद्मन् *n.*, अपदेशः, निमित्तं, कारणं, मोचनहेतुः. 3 वादः, व्यवहारः, कार्यं. 4 प्रार्थना; 'raising a p.' स्वजीकरणं. —**Plead,** *v.* उत्तरं दा 3 U or प्रतिपद् 4 A or वद् 1 P, निमित्तं कृ c., वि-,अप-दिश् 6 P; 'p. guilty' अपराधी अस्मीति वद् or प्रतिपद्; 'tears shall p. in vain' अश्रुपातो निर्गुणो भवेत्. 2 विनयेन प्रार्थ् or अभ्यर्थ् 10 A, सविनयं याच् 1 A; 'p. ed for his life' जीवितत्राणार्थं प्रार्थयामास. 3 उप-क्षिप् 6 P, उपन्यस् 4 U, व्यपदेशार्थं पुरः क्षिप्. 4 (Cause) प्रति-पद् c., परार्थं उत्तरं वद्, परपक्षं समर्थ्; 'p. ing head-ache as an excuse' शिरःशूलस्पर्शं व्यप-दिशन्; 'p. ing illness' अस्वास्थ्यव्याजेन-व्यपदेशेन. —**er,** *s.* अभिभाषकः, उत्तरवादिन् *m.* समर्थकः, हेतुवादिन् *m.* —**ing,** *s.* हेतु-उत्तर-वादः, व्यपदेशनं, हेतूपन्यासः.

Please, *v. i.* प्री 9 P, 10 (प्रीणयति), तुष् c., सं-परि-°, रम् c. (रमयति), प्रमुद् c., सुखयति (D.), आ-नंद् c., सं-,तुष् c., प्रसद् c., आह्लाद् c., हृष् c., आराध् c., अनुरंज् c.; oft. by इच्छा, प्रसादः, कृपा; विश्रमय्यसुतं कश्चिद्रनेषुसुतं वा विश्रमीश्वरे-च्छया (R. VIII. 46) 'if it p. God to do so' &c.; 'he was p. ed to accept my presents' मदीयोपायनानि स सुप्रीतमनसा-सुप्रसन्नं-स्वीचकार; 'may it p. your ladyship' प्रसीदतु भट्टिनी (M. 4). 2 (Like) *See* below. —*v. i.* 'to be p. ed' तुष् 4 P, तुप् 4 P; रम्-मुद् 1 A, नंद् 1 P. 2 अर्ह् 1 P or प्रसद् 1 P, with inf., or simply by Imperative; 'p. sit here' अत्रोपवि-श्यतामः; 'worthy Sir , p. to wait for 2 or 3 days' द्वित्राण्यहान्यर्हसि सोढुमर्हन् (R. V. 25) 3 रुच् 1 A, इष् 6 P; *See* **Like;** 'just as my friend p. s' यथाभि-रोचते वयस्याय; 'do as you p.' यथा-भिलषितं क्रियतां. —**ance,** *s.* क्रीडोद्यान. —**ant,** *a.* सुखकर (री *f.*), मधुर, सुखद-प्रद, सुखावह, रम्य, रमणीय, प्रिय, मनोहर-रम, अभिराम, सुभग, अभिमत, हृद्य, काम्य, कांत, हर्षावह, रुचिर, इष्ट, हृदयंगम, प्रीति-तुष्टि-कर, मनोज्ञ, मंजुल, चारु; 'a p. joke' हृदयंगमः परिहासः (Mal. 3). —**antly,** *adv.* सुखं, रम्यं, मधुरं, प्रियं, रुचिरं. —**antry,** *s.* परि(री)हासः, नर्मभाषितं, विनोदः, नर्मालापः, विनोद-नर्म-उक्ति *f.* —**ing,** *a.* सुख in comp.; रम्य, कांत; *See* **Pleasant.** 'p to the ear' सुखश्रव, श्रुतिसुख, मंजुल-स्वन, सुश्राव्य; 'p. to the eye' प्रेक्षणीय, नयनाभिराम, सुदृश्य; 'p. language' चाटु *m. n.*, चाटूक्तिः. —**ingly,** *adv.* सुभगं, सुखं, सुख-चारु in comp. —**Pleasure,** *s.* सुखं, सं-परि-तोषः, आनंदः, प्रीति *f.*, सौख्यं, तुष्टि *f.*, प्र-, मोदः, आह्लादः, हर्षः, मुदा. 2 अभि-, रुचि *f.*, इच्छा, अभिलाषः, छंदः-वृत् *n.*, कामः; 'at one's p.' स्वेच्छया, कामतः, यथाकामं, यदृच्छया, स्वैरं; 'wandering at p.' कामचारिन्, स्वच्छंद-गामिन्; 'sensual p.' भोगः, विषयसुखं, विषयानुरागः; 'sexual p.' रति *f.*, रति-सुखं, सु-,रतं; 'p.-boat' केलि-क्रीडा-नौका; 'p.-ground' आरामः, क्रीडा-केलि-विलास-वनं-कानन, प्रमदवनं, क्रीडोद्यानं; 'p.-mansion' केलिगृह-भवनं, लीलागारं, विलासमंदिरं. 3 प्रसादः, अनुग्रहः. —**able,** *a.* रम्य, रमणीय, सुखद, सुख; *See* **Pleasant.** —**ist,** *s.* विषयिन् *m.*, विषयासक्तः, भोगा-सक्तः, भोगपरायणः.

Plebian, *a.* प्राकृत (ती *f.*), सामान्य, साधारण (णी *f.*), अवरवर्ण, अकुलीन. —*s.* प्राकृतः, प्राकृतजनः, पृथग्जनः, नीच-अवर-जनः.

Plectrum, *s.* कोणः, शारिका.

Pledge, *s.* न्यासः, निक्षेपः, आधिः, उपनिधिः, उपन्यासः-निक्षेपः, पणः. **2** अभिज्ञानं; 'p. of love' प्रीत्यभिज्ञानं. **3** प्रतिज्ञा, पणः, परिपणः-नं, 'I have given a p.' विहित-प्रतिज्ञः-गृहीतक्षणः-अहं. **4** प्रतिभूः, लग्नकः, बंधकः. -*v. i.* न्यस् 4 U, निक्षिप् 6 P, आ-नि-धा 3U, परि-,पण् 1 A, आधी-न्यासी-कृ 8 U. **2** (One's word) प्रति-ज्ञु 5 P, प्रति-ज्ञा 9 A, (with dat. of person), उरीकृ, वचनेन बंध् 9 P; ex. by (*s.*); अस्मत्सौधाग्निमीसमक्षमनयोर्वृत्तये प्रतिज्ञा (Mal. 1) 'they two p. ed their word' &c.; 'he has p. ed his virtue (honor) that he would not harm you' तव विरूपकरणे तेन सुकृतमंतरे धृतं (P. iv. 1) 'he who has p. ed his word' कृत-विहित-प्रतिज्ञः, प्रतिज्ञा-वचन-बद्धः, कृतवचनः-प्रतिज्ञः, गृहीतक्षणः.

Pledget, *s.* पट्टः, आवेष्टनं.

Pleiades, *s.* कृत्तिकाः.

Plenary, *a.* सं-परि-पूर्ण, समग्र.

Plenipotent, *a.* पूर्णशक्तियुक्त. -**Plenipotence,** *s.* पूर्णसामर्थ्य शक्ति *f.* **Plenipotentiary,** *s.* पूर्णशक्तियुक्तः, महादूतः.

Plenish, *v. t.* उपस्कृ 8 U, परि-छद् 10.

Plenist, *s.* पूर्णतावादिन् *m.*

Plenitude, *s.* पूर्णता, प्राचुर्य, वैपुल्यं, समृद्धि *f.*, अतिरेकः, उत्सेकः, परा कोटिः-काष्ठा.

Plenty, *s.* बाहुल्यं, प्राचुर्य, वैपुल्यं, बहुत्वं, समृद्धि *f.*, उद्रेकः, अतिरेकः, उत्सेकः, स्फीति-वृद्धि- *f.* -**Plenteous, Plentiful,** *a.* प्रचुर, प्रचुर, विपुल, पटु, बहुल, भूरि, भूयिष्ठ, पुष्कल, समृद्ध, सं-परि-पूर्ण, उद्रिक्त, स्फीत, उत्सिक्त, उपचित. -**ly,** *adv.* बाहुल्येन, बहुशः, भूयिष्ठं, भूरि, प्रचुरं, विपुलं, अतिरिक्तं. -**ness,** *s.* बाहुल्यं, प्राचुर्य; *See* (*s.*).

Pleonasm, *s.* अधिकपददोषः; शब्दाधिक्यं, शब्दातिशयः. -**Pleonastic,** *a.* अधिकशब्द, बहुपद.

Plethora, *s.* रक्तपित्तं. **2** बाहुल्यं, प्राचुर्य, अतिवृद्धि *f.* -**Plethoric,** *a* रक्तपित्तरोगिन्.

Pleurisy, पार्श्वशूलं.

Plexus, *s.* नाडी-शिरा-जालं.

Pliant, Pliable, *a.* आ-,नम्य, सुखनम्य, मृदु, शिथिल, अदृढ, आयम्य.

Pliers, *s.* *See* '**Pincers.**'

Plight, *s.* दशा, अवस्था, स्थिति *f.*, भावः, वृत्ति *f.*, गति *f.*; 'sorry p.' दुर्दशा, दुर्गतिः. **2 Pledge.** q. v. -*v. t.* प्रति-ज्ञा 9 A, न्यस् 4 U; *See* **Pledge.** -**ed,** *a.* प्रतिज्ञात, न्यस्त; 'p. word' विहितप्रतिज्ञा, संगरः, अभिसंधिः.

Plinth, *s.* स्तंभमूलं-तलं; प्राकारमूलं.

Plod, *v. i.* अविरतं श्रम् 4 P or आयासं कृ 8 U, मंदं मंदं आयस् 1, 4 P. -**der,** *s.* मंदं मंदं निरंतरायासिन् *m.*, नित्योद्योगिन् *m.* पिपीलिकाधर्मिन् *m.* -**ding,** *s.* अविरतश्रमेण निरंतरश्रमः-नित्यायासः.

Plot, *s.* भू-भागः-प्रदेशः, क्षेत्रं, स्थली-ली, भू-भूमि-*f.* **2** कपटप्रबंधः, कुप्रबंधः, कपटोपायः, मंत्रणा, कु-संकल्पः-मंत्रणा-कल्पना, कूटोपायः, उपजापः; (generally) उपायः, संकल्पः, प्रयोगः. **3** कथा, वस्तु *n.*: 'arrangement of p.' वस्तुरचना-विन्यासः; 'the p. of which is composed by Kālidāsa' कालिदासग्रथितवस्तु नाटकं (S. 1.) -*v. i.* कपटप्रबंधान् चिंत् 10 or युज् 10, उपायान् क्लृप् c. or निरूप् 10 or अनुसं-धा 3 U; 'p. against' द्रुह् 4 P (with dat.), अभिद्रुह् (with acc.); 'p. against one's life' जीवितापहरणाय कपटप्रबंधान्रचयति. -**ter,** *s.* कुमंत्रणाकृत् *m.*, अभिद्रोग्धृ *m*

Plough, *s.* हलं, लांगलं, सीरः (सीरः), हालः, गोदारणं; 'body of a p.' निरीशं-षं; कुटकं, फालः, कृषकः; 'pole of a p.' ईषा-षा, (लांगलीषा), लांगलदंडः; 'handle of a p.' ईषा-दंडः; 'furrow made by a p.' सीता, लांगलपद्धति *f.*; 'p.-boy' बालकर्षकः; 'p.-gear' हलसज्जा-उपकरणं; 'p.-land' सीत्यं, हल्यं, फालकृष्टं, हल्यक्षेत्रं; 'p.-man' हालिकः, लांगलिन् *m.*, हलिन् *m.* लांगलिकः, सैरिकः, हलधरः-भृत् *m.* कृषकः, कर्षकः; 'p.-share' कुशी, फालः, कृषकः. -*v. t.* कृष् 1 P, 6 U, भिद् 7 P, विद् 9 P or c., उत्कृष् 1 P, (सद्यः सीरोत्कषणसुरभि Me. 16). -*v. i.* हलं वह् c. or चल् c. -**ed,** *a.* कृष्ट, हल्य, सीत्य; 'twice, thrice, p.' द्वि-त्रि-हल्य; 'p. after sowing' बीजाकृत, उप्तकृष्ट. -**er,** *s.* कर्षकः, हालिकः. -**ing,** *s.* कर्षणं, उत्कर्षणं, भूमिदारणं.

Pluck, *v. t.* (Off) लू 9 U, निष्कृष् 1 P; 'crows with feathers p. ed off' लून-पक्षाः काकाः; (out) उत्पट् 10, सं-,उद्धृ 1 P, निर्हृ; (hair) लुंच् 1 P, अव-उत्-°, उत्पट् c.; (up) उन्मूल् 10, उत्-खन् 1 P, उच्छिद् 7 P, उत्पट्, उद्धृ, कृष्. **2** (Gather) चि 5 U, अव-सं-°, लू, छिद्, आ-दा 3 A, ग्रह् 9 U. -*s.* सत्त्वं, वीर्यं, पौरुषं, उत्साहः; *See* **Courage.** -**ing,** *s.* उत्पाटनं, उद्धरणं, उन्मूलनं, अव-,चयः.

Plug, *s.* रोधनी, स्तंभनी. -*v. t.* पि-धा 3 U, स्तंभ् 9 P.

Plum, *a.* कर्कंधूः,-फलं; *See* **Jujube.**

Plumage, *s.* पक्षाः (pl.), पिच्छकलापः, बर्हभारः, पक्षः, पर्ण, पतत्रं, गरुत् *n.*

Plumb, *s.* लंबः,-सूत्रं. -*a.* लंब, ऋजु, लंबरूप. -*v. t.* सूत्रेण समायुज् 7 U, 10. **2** वेधं परि-मा 3 A, 2 P. -**er,** *s.* सीसकारः.

Plume, *s.* पक्षः, पर्णं, पिच्छं; *See* **Feather.** 2 शिखा, चूडा, शेखरः. **-v.** *t.* पर्णानि रच् 10. 2 पक्षान् छिद् 1 P or उत्पट् 10. 3 (Oneself upon) आत्मानं श्लाघ् 1 A, विकत्थ् 1 A; 'p. s himself upon his learning' ज्ञानेन आत्मानं अतीव श्लाघते-विकत्थते, पंडितंमन्यः, पंडितमानी. **-less,** *a.* पक्षहीन. **-ous,-ose,-y, Plumigerous,** *a.* सपक्ष, पक्षवत्, पक्षविशिष्ट.

Plummet, *s.* लंबः, लंबसूत्रं, लंबसीसकं, सीसकसूत्रं.

Plump, *a.* पीन, पीवर, पुष्ट, स्थूल, उच्छून, आप्यान, स्फीत; *See* **Fat.** **-adv.** अकस्मात्. **-v.** *t.* आप्यै c., श्वि c., स्फाय् c. (स्फावयति). **-ly,** *adv.* व्यक्तं, स्पष्टं. **-ness,** *s.* पीनता, पुष्टि *f.*, स्फीति *f.*

Plunder, *v. t.* (धनादि) अप-,हृ 1 P, मुष् 9 P, चुर् 10, वि-,लुंठ्-ट् 1 P, 10. **-s.** विलुंठनं, लोत्रं, लोप्त्रं, अपहारः, अपहृतं धनं. **-er,** *s.* अपहारकः, विलुंठकः, मोषकः. **-ing,** *s.* अपहारः, अपहरणं, मोषणं.

Plunge, *v. i.* मस्ज् 6 P, नि-अव-°, आप्लु 1 A, गाह् 1 A, वि-अव-°, प्रविश् 6 P. **-v.** *t.* Causal of roots above. **-s.** अवगाहः-हनं, नि-,मज्जनं, आप्लवः, प्रवेशः. **-ed,** *a.* मग्न, अवगाढ, आप्लुत, लीन, प्र-नि-विष्ट.

Plungeon, *s.* प्लवः, प्लाविन् *m.*

Plural, *a.* (Number) बहुवचनं. 2 अनेक, बहु. **-ity,** *s.* बहुत्वं, अनेकता, ex. by 'Many' q. v.

Plus, *s.* धनं; सहित, संकलित in comp.

Pluto, *s.* यमः, कालः, कृतांतः.

Plutocracy, *s.* धनवत्सत्तात्मकं राज्यं. **-Plutocrat,** *s.* धनवत्-सत्तावत् *m.* -शासितृ *m.*

Pluvial, Pluvious, *a.* वृष्टिमत्, प्रचुर-बहु-वृष्टि.

Ply, *v. t.* पत् c., धा 3 U, व्यस् 4 U, प्रयुज् 7 A, 10; पुनः पुनः प्रयुज् or व्यापृ c., सततं व्यापृ c.; 'p. thy work' कार्यव्यापृतो भव, कार्यं निर्वाहय; 'p. thy needle' सूच्या कार्यं प्रवर्तस्व. 2 (प्रयत्नेन) चल् c., संचर्-स् c. 3 आग्रहेण उप-स्था 1 U, अनुनिर्बंध् 9 P; *See* **Importune;** 'p. with entreaties' अतिप्रार्थनया उद्विज् c. **-v.** *i.* अविरतं व्यापृ 6 A or प्रवृत् 1 A or उद्यम् 1 A or चेष्ट् 1 A. **-s.** पुटः, भंगः; *See* **Fold.**

Pneumatic, *a.* वायुमय, वायुमय (यी *f.*), वायव (वी *f.*), वायु in comp. **-s.** (P. s) वायुविद्या-शास्त्रं.

Pneumonia, *s.* क्लोमपाकः.

Poach, *v. t.* ईषत् पच् 1 P. 2 (Game) कूटोपायेन ग्रह् 9 U or अपहृ 1 P or चुर् 10. 3 प्रहणार्थं अनुसृ 1 P or अनुगम् 1 P; *See* **Pursue. -er,** *s.* मृगयाचौरः, आखेटचौरः. **-ing,** *s.* मृगया-जांगल-चौर्यं, पशिहरणं.

Pock, *s. See* **Pimple. -mark,** *s.* मसूरिका-क्षत-चिह्नं.

Pocket, *s.* कोषः, आधारः. **-v.** *t.* कोषे नि-धा 3 U, (छलेन) आत्मसात्कृ 8 U. 2 (Insult) सह् 1 A; *See* **Bear. -ed,** *a.* कोषस्थ, कोषांतर्गत, अंतर्हित.

Pod, *s.* बीजकोषः-षी *f.*, शिंबा, शिंबि-बी *f.*, शिंबिका.

Podagrical, *a.* वातकिन्, वातरोगिन्.

Poet, *s.* कविः, सूरिः; 'a ready p.' शीघ्रकविः. **-ic,-ical,** *a.* Ex. by कविता-काव्य in comp.; 'p. genius' कवित्वशक्तिः. 2 श्लोक-कविता-रूप-बद्ध, पद्यमय (यी *f.*), छंदोबद्ध-रूप, पद्यात्मक; 'p. work' पद्यात्मको ग्रंथः. **-ically,** *adv.* पद्यरूपेण, छंदोरूपेण. **-Poetics,** *s.* काव्यशास्त्रं, पद्यशास्त्रं; साहित्यं. **-Poetry,** *s.* काव्यं, कविता. 2 पद्यं (opp. of prose). 3 काव्यरचना, कवित्वं, कवितविद्या. **-Poetaster,** *s.* कुकविः, कविद्वेष्यः. **-Poem,** *s.* काव्यं, काव्यप्रबंधः, काव्यबंधः, कविता; 'a p. interspersed with prose' खंडकाव्यं. **-Poesy,** कवित्वं-ता. 2 काव्यरचना, कविताशक्ति *f.*

Poignant, *a.* उग्र, तीक्ष्ण, तीव्र, तिग्म, अरुंतुद, मर्मस्पृश्-भिद्. **-Poignancy,** *s.* तीक्ष्णता, तीव्रता.

Point, *s.* अग्रं, अणिः-णी *f.*, धारा, कोटि *f.*, अश्रि *f.*, पालि-ली *f.*; शिखा, शिखरं. 2 (Of land) जलप्रस्थलं, भूनासिका. 3 मर्मन् *n.*, रहस्यं, रसः. 4 दिश्-शा, ककुभ्, आशा, हरित्, काष्ठा, (all *f.*). 5 बिंदुः, चिह्नं, अंकः. 6 आशयः, अभिप्रायः, उद्देशः, अर्थः, लक्ष्यं. 7 पर्यंतः, अंतः, अवधिः, परिमाणं. 8 विषयः, पदं, वस्तु *n.*, अर्थः, स्थानं, स्थलं, आस्पदं, प्रकरणं, प्रस्तावः; 'p. at issue' विवादवस्तु-विषयः. 9 लक्षणं, विशेषचिह्नं, विशेषणं, विशिष्टगुणः. 10 प्रसंगः, कालः, समयः; 'being to the p.' प्रास्ताविक (की *f.*), प्रकृत, प्रस्तुत; 'to such a p.' एतावत्, एतावत्पर्यंतं; 'come to the p.' प्रस्तुतमनुसंधीयतां; 'on the p. of' ex. by उन्मुख (खी *f.*), उद्युक्त, उद्यत, by desid. or by fut. part., आसन्न in comp.; 'on the p. of death' मरणोन्मुख, आसन्नमृत्यु, मुमूर्षु; 'on the p. of departing' निर्गमोद्यत, निर्जिगमिषु; 'on the p. of delivery' प्रसवोन्मुखी, आसन्नप्रसवा; 'gain a p.' अभीष्टं साध् 5 P; 'p. of view' दृष्टि *f.*; *See* under **View. -v.** नि-शो 4 P; तिज् c., तीक्ष्णीकृ 8 U. 2 अपदिश् 6 P, सं-ज्ञा 3 U, लक्षीकृ, अभि-भेद् c.; 'p. ing to it' तदुद्दिश्य, तदुद्दिश्य. 3 (Out) प्र-उप-आ-

दिश् (as a way); (at) अंगुल्या निर्दिश् or अंग-क्षिप् 2 P, (मार्गमंगुलीकृतमिसेनाकल्पयन्; Mal 1); 'p. ing towards the north ' उदङ्मुख, उत्तराभिमुख; 'p. blank ' स्पष्ट, असंदिग्ध. **-ed,** *a.* ति-,तिग्म, तीक्ष्णाग्र, साग्र, सधार; oft. by सूचि *f.*; 'pricked by the p. Kusa grass' कुशसूचिविद्धे (S. 4); *See* **Sharp.** 2 मार्मिक (की *f.*), अरुंतुद, मर्मस्पृश्-भिद्; सरस, रसिक, रसपूर्ण. 3 निर्दिष्ट, सूचित &c. **-edly,** *adv.* उद्दिश्य, उद्देशपूर्वं, मर्मभेदपूर्वं, स्पष्टं, विशदार्थं. **-er,** *s.* निर्-प्र-,देशकः, प्र-,दर्शकः, सूचकः. 2 (Of a dial) प्रदेश(शि)नी. **-ing,** *s.* निर्देशः, सूचनं, अंगुलिनिर्देशः. **-less,** *a.* धाराहीन, अनिशित, अतीक्ष्ण, निराग्र. 2 रसहीन, अरसिक, फल्गु. 3 अप्रकृत, अप्रस्तुत.

Poise, *v. t.* तुल् 10, तुल्यी-समीकृ 8 U, समभारीकृ. **-s.** भारः, तोलः. 2 भारतुल्यतासाम्यं, समभारता, समतोलः, तुल्यता.

Poison, *s.* विषः-षं, गरलं, क्ष्वेडः, जांगुलं; 'administering p.' विषप्रयोगः-दानं; 'curing p.' विषघ्न (घ्नी *f.*), विषापह, विषहर (री *f.*); 'curer of p.' विषवैद्यः, जांगुलिकः. **-v. t.** विषेण दिह् 2 U or अंज् 7 P or मिश्र् 10. 2 विषं दा 3 U, विषदानेन हन् 2 P or मृ c. or नश् c.; (oneself) विषं भक्ष् 10 or सेव् 1 A or भुज् 7 A. 3 कलुषीकृ 8 U, दुष् c. (दूषयति). **-ed,** *a.* विषाक्त, विषदिग्ध, विषलिप्त; 'p. arrow' विषाक्तः, दिग्धः, लिप्तकः. 2 विषनाशित. **-er,** *s.* विषघातिन् *m.*, विषदायिन् *m.* **-ous,** *a.* विषमय (यी *f.*), सविष, विषालु, सगर, विषपूर्ण, गरविशिष्ट, विष in comp.

Poke, *v. t.* (Fire) ज्वल् c., उत्तिज् c. 2 तड् 10, आहन् 2 U; प्रहृ 1 P. 3 (दंडादिना) परामृश् 6 P, अन्विष् 4 P. **-v. i.** **Grope,** q. v. **-s.** ताडनं, प्रहारः, आघातः. **-er,** *s.* उत्तेजनी (शलाका); अंगारोत्थापकः.

Pole, *s.* यष्टि *f.*, दंडः, काष्ठं; 'raised on a p.' उद्दंड. 2 (Of a carriage) धुर् *f.*, धुरा; कूबरः, युगंधरः. 3 दंडः. 4 ध्रुवः-चक्रं; 'p.-axe' परशुः, कुठारः, परश्वधः; 'p.-cat' गंधमार्जारः; 'p.-star' ध्रुवः, उत्तानपादजः, नक्षत्रनेमिः, ज्योतीरथः; ध्रुवतारा. **-Polar,** *a.* ध्रुव in comp.; 'p. longitude' ध्रुवः. **-ity,** *s.* ध्रुवाभिमुखता,ध्रुवाभिसारिता. **-y,** *a.* ध्रुवाभिसारिन्, ध्रुवाभिगामिन्.

Polemics, *s.* वादानुवादः. **-Polemic,-al,** *a.* विवादात्मक, वादानुवादार्थक, वादकुशल. **-s.** विवादकुशलः, वादानुवादशीलः.

Police, *s.* रक्षापुरुषाः; नगररक्षिणः, नगरपालाः (all pl.), रक्षिगणः-वृंदः; 'rural p.' ग्रामरक्षिणः, ग्रामपालाः; 'p.-man', 'p. officer' नगररक्षिन् *m.* नागरिकः, रक्षिन् *m.* राजपुरुषः; 'p. magistrate' दंडाधिकारिन् *m.*

Policy, *s.* नीति *f.*, नयः, नीतिक्रमः-मार्गः, राजनीतिः-नयः, राज्यशासनरीतिः-मार्गः. 2 नीतिचातुर्यं, चैतुर्यं, राज्यशासनकौशलं, नीतिज्ञता. 3 युक्ति *f.*, प्रयोगः, उपायः, व्यवहारः, रीतिः; 'prudential p.' समीक्षा, समीक्ष्यकारित्वं; 'bad p.' कुप्रयोगः, कुयुक्तिः. 4 (a written contract) नियमपत्रं, समयलेखः. **-Politic,** *a.* नीतिज्ञ, नीतिविद्-कुशल, नयविद्-ज्ञ, नीतिचतुर-निपुण. 2 व्यवहारकुशल-दक्ष, विचक्षण, कुशल, चतुर, निपुण. 3 सुप्रयुक्त, सुघटित, सुनीत, समीक्ष्यकृत, हित, सु pr. **-al,** *a.* नीति-राज in comp.; 'p. affairs' राजकार्याणि; 'p. science' राजनीतिशास्त्रं; 'p. economy' अर्थशास्त्रं, अर्थविज्ञानं; 'he led a p. life' राजकार्यव्यापृतो जीवितमत्यवाहयत्; 'p. institutions' राज्यतंत्राणि; 'p. rights' राज्यनिर्वाहाधिकाराः. **-ian,** *s.* नीतिज्ञः, नीतिविद् *m.* -कुशलः, नयज्ञः-विद् *m.*, राजनीतिनिपुणः, राजकार्यधुरंधरः. **-Politics,** *s.* नीतिः, नयः, राजनीतिः, राज्यशासनशास्त्रं. 2 राजकार्याणि, राज्यव्यवहाराः. **-Polity,** *s.* राजनीतिः-रीतिः-व्यवस्था, दंडनीतिः; (generally) नीतिः, व्यवस्था, विधिः.

Polish, *v. t.* तिज् c., घृष् 10, निः-तप् c., प्र-,मृज् 2 P or c., परिष्कृ 8 U, श्लक्ष्णीकृ, कांतिं दा 3 U. 2 परिष्कृ, वि-नी 1 P, उपस्कृ 8 U, संस्कृ (lit. also); आदर्शे निर्घर्षणक्रियया संस्क्रियमाणे (S. B. 72). **-s.** कांति *f.*, शोभा, तेजस् *n.*, स्निग्धता, श्लक्ष्णता. 2 संस्कारः, परिष्कारः, सभ्यता, शिष्टता, सौजन्यं. **-ed,** *a.* निघृष्ट, परिष्कृत, प्रमृष्ट, निर्धौत, उत्तेजित. 2 शिष्ट, संस्कृत, सभ्य, परिष्कृत, विनीत, अग्राम्य. **-er,** *s.* तेजकः, कांतिदः, मार्जकः, परिष्कारकः; *See* **Furbisher.**

Polite, *a.* दाक्षिण, सौजन्यवत्, सुजन, विनीत, शिष्ट, सभ्य, संस्कृत, सभ्यशील, शिष्टाचार, सुशील, आदरशील, प्रियंवद. **-ly,** *adv.* सौजन्येन, दाक्षिण्येन, सविनयं, शिष्टवत्. **-ness,** *s.* शिष्टता, सभ्यता, सौजन्यं, विनयः, दाक्षिण्यं, सुशीलता 2 शिष्टाचारः, सुशीलवृत्ति *f.*

Poll, *s.* शीर्षं, शिरस् *n.*; *See* **Head.** 2 नामावलि-ली *f.*; नामलिखनं, नामारोपणं. **-v. t.** (केशान्) लू 9 U, छिद् 7 P, आवप् 1 P. 2 नामानि लिख् 6 P or निविश् c.

Pollard, *s.* छिन्नाग्रवृक्षः.

Pollen, *s.* [illegible]-[illegible]गः, रजस् *n.*, पांशुः, पुष्परजः-पराग[illegible]

Pollute, *v. t.* [illegible]-कलुषयति-(D.), दुष् c. (दूषयति), मलिनी-कलुषी-कृ 8 U, मलेन लिप् 6 P or दिह् 2 U. 2 भ्रंश् c., दुष् c., आदुष् c., सतीत्वं भ्रंश् c.

or मह्र् c. -er, s. दूषकः, आधर्षकः. -ion, s. दूषणं, कलुषीकरणं. 2 मालिन्यं, अमेध्यता, कालुष्यं, मलं, कलंकः, अशौचं. 3 Emission, q. v.

Poltroon, s. See **Coward.**

Polyandry, s. अनेकभर्तृकता. -ist, s. अनेकपतिका, बहुभर्तृका.

Polychrome, a. बहुवर्ण.

Polygamy, s. अनेकपत्नीकता, बहुभार्यत्वं. -ist, s. बहु-अनेक-भार्यः. 2 बहुपत्नीवादिन् m.

Polygenous, a. बहु-विध-प्रकार-जाति.

Polyglot, a. बहुभाषामय (यी f.).

Polygon, n. बहुभुजः, बहस्रं. -al, a. बहु-कोण-भुज-अस्र

Polymathy, s. बहुशास्त्रज्ञानं.

Polypetalous, a. बहु-अनेक-पर्ण.

Polyphonous, a. बहुस्वर-स्वन.

Polypus, s. अनेकपादः, बहुमूलः.

Polysyllabic, a. बह्वक्षर, अनेकाच्. [शाला.

Polytechnic, s. बहुकला-बहुव्यवसाय-पाठ-

Polytheist, s. अनेकदेववादिन् m. -**Polytheism,** s. बहुदेववादः.

Pomade, Pomatum, s. See **Perfume.**

Pomegranate, s. (Fruit) दाडि(लि)-मं, दाडिमफलं; (tree) दाडि(लि)मः, डालिमः, दाडिंबः, करकः.

Pommel, s. गुल्मः, पिंडः, गंडः. -v. t. तड् 10, प्रह् 1 P.

Pomp, s. आडंबरः, शोभा, श्रीः, प्रतापः, ऐश्वर्यं, वैभवं. -ous, a. विभ्राजमान, शोभन, सश्रीक, साडंबर, अतिशोभन, महाप्रताप. 2 दांभिक (की f.), साटोप, गर्वित, दर्पध्मात; (style) सालंकार, अलंकृत. -ously, adv. साडंबरं, अतिशोभया, अतिप्रतापेन. 2 सदंभं, साटोपं, सगर्वं. -ousness, s. ऐश्वर्यं, &c. 2 दंभः, आटोपः.

Pond, s. तडागः-गं, जलाशयः, कासारः, जलाधारः, पद्माकरः, सरसी, सरस् n.; 'deep p.' ह्रदः; 'small p.' पल्वलः-लं, वेशंतः, अल्पसरः; (for drinking water) आहावः, निपानं.

Ponder, v. चिंत् 10, ध्यै 1 P, विचर् c., विमृश् 6 P, मनसा क्लृप् c. or भू c. or विगण् 10; See **Meditate.**

Ponderous, a. अतिगुरु, भारवत्, अतिभारिन्, सभार. -ly, adv. अतिभारेण. -**Ponderosity,** s. भारवत्त्वं, अतिगुरुता.

Poniard, s. कृपाणिका, छुरिका, असिपुत्रिका, असिधेनुका.

Pontage, s. सेतुसंधानशुल्कं.

Pontiff, s. प्रधानधर्माध्यक्षः, मुख्यपुरोहितः. -**Pontificate,** s. धर्माध्यक्षाधिकारः.

Pony, s. अश्वशावः, क्षुद्रघोटकः.

Pool, s. जलाशयः, जलाधारः, कुंडं, पल्वलं. निपानं; See **Pond.**

Poop, s. नौपृष्ठं, नौपश्चाद्भागः.

Poor, a. दरिद्र, निर्धन, निःस्व, दीन, अधन, अकिंचन, धन-द्रव्य-अर्थ-हीन, अल्प-धन-विभव, दुर्गत, परिक्षीण, क्षीणधन; 'to be p.' दरिद्रा 2 P. 2 दीन, तपस्विन्, वराक (की f.), कृपण, अनुकंप्य. 3 कुत्सित, अपकृष्ट, तृणप्राय, तुच्छ, गर्हित, अधम, विगुण; oft. ex. by कु, कद्, दुर्, अप, in comp.; 'p. food' कदन्नं; See **Bad, Mean;** 'p. soil' निर्गुणा-असारा-भूमिः, इरिणा-रूक्षा-भूमिः; 'p. house', 'p. asylum' दरिद्रालयः, अनाथालयः, दरिद्रगृहं; 'p.-spirited' दीन-कृपण-बुद्धि, कृपण, अल्पसत्त्व, क्षुद्रमति. -ly, adv. दरिद्रवत्, दीनं, निर्धनवत्; 'p. dressed' दीनवेषं दधान. 2 निष्फलं, व्यर्थं, सिद्धिं विना. -ness, **Poverty,** s. दारिद्र्यं, दैन्यं, निर्धनता, निःस्वता. दुर्गति f., दरिद्र-दशा-अवस्था, आकिंचन्यं; 'reduced to p.' सन्न or धन-विभव or धन, दुर्गत; See (a.); 'struck with p.' दारिद्र्योपहत, दारिद्र्यग्रस्त.

Pop, s. आकस्मिकध्वनिः-शब्दः. -v. i. अकस्मात् प्रविश् 6 P. 2 सहसा निर्गम् or निःसृ 1 P. 3 सहसा क्वण्-स्वन्-1 P. -v. t Causal of roots above.

Popinjay, s. See **Parrot.**

Poppy, s. खसतिलः.

Populace, s. लोकः, जनः, सामान्य-प्राकृत-जनाः; See **People.** -**Popular,** लोक-जन-प्रिय, सर्वप्रिय. 2 लौकिक (की f.) लोकप्रसिद्ध, लोकरूढ-संमत, जन-लोक in comp.; 'p. scandal' लोकापवादः; 'seeking p. favor' लोक-जन-रंजन; 'p. usage' रूढि f., जनव्यवहारः, लोकाचारः, लोकमर्यादा-रीति f; 'p. report' जनप्रवादः; लोक or जन-वार्ता or श्रुति f., किंवदंती; 'p. tumult' प्रकृतिक्षोभः; 'conformity to p opinion' लोकानुसरणं. 3 सामान्य, साधारण (णी f.). -ity, s. लोकप्रियता, लोक-जन-प्रीति f-अनुरागः संमानः. -ly, adv. लोके, लौकिकतया, साधारणतः, सामान्यतः, लोकरंजनार्थं. -**Populate,** v. t. वस् c., जनैः आकॄ 6 P or पूर् 10. -v. i. प्रजा उत्पद् c. प्रजन् 4 A. प्रजावृद्धिं कृ 8 U. -ion, s. प्रजा, प्रजा-लोक-संख्या, जनाः, लोकाः. -**Populous,** a. जनाकीर्ण, जनसंकुल-पूर्ण, बहु or प्रचुर-जन or प्रज, जनसंबाध. -ness, s. लोक-प्रजा-बाहुल्यं.

Porcelain, s. (चीनदेशीय) मार्त्तिकं, कौलालकं, मृद्भांडानि.

Porch, s. प्रघाणः, प्रघणः, अ(आ)लिंदः, द्वारप्रकोष्ठः.

Porcine, a. शूकरोपम, शूकरसंबंधिन्.

Porcupine, *s.* शल्यः-ल्यकः, श्वाविध् *m.*; 'quill of a p.' शलं, शललं-ली.

Pore, *s.* रोम(लो)गर्त-कूपः. 2 (सूक्ष्म) रंध्रं, कूपः. **–***v. i.* अनन्यवृत्त्या-साभिनिवेशं अधी 2 A or पठ् c. **–ous,** *a.* बहुरंध्र, रंध्रबहुल, रंध्रपूर्ण-विशिष्ट, सरंध्र. 2 रोमकूपमय (यी *f.*), स्वेदमार्गविशिष्ट, विरलावयवक. **–ousness, Porosity,** *s.* रंध्रबाहुल्यं, रंध्रविशिष्टता.

Pork, *s.* शूकर-वराह-मांसं. **–er,** *s.* शूकरः, वराहः.

Porpoise, *s.* शिशुकः, शिशुमारः, उलूपिन् *m.*

Porridge, *s.* यूषं, जूषं.

Porringer, *s.* यूषपात्रं-भाजनं.

Port, *s.* नौकाश्रयः, नौकाश्रयः, उत्तरणस्थानं, आश्रयः, रक्षणस्थानं, आशयः; 'arrived at the wished-for p.' इष्टदेशं जगाम. 2 द्वारं; *See* **Door.** **-able,** *a.* वहनीय, लघुभार, सुवाह्य, लघु, सुखवाह्य, हस्तवाह्य. **–er,** *s.* द्वाःस्थः, द्वारपालः, प्रतीहारः, दौवारिकः. 2 भारवाहः, भारहरः, वोढृ *m.*, भारिकः. **–erage,** *s.* भारवहनं. 2 वहनमूल्यं. **–Portal,** *s.* द्वारं, मुखं, प्रवेशद्वारं; *See* **Door.**

Portend, *v. t.* अग्रे (अनिष्टं) सूच् 10 or निर्दिश् c. or शंस् 1 P. **–Portent,** *s.* उत्पातः, दुर्निमित्तं, अशुभलक्षणं, अजन्यं, उपसर्गः, दुर्लक्षणं, दुश्चिह्नं, अपशकुनं, कुलक्षणं, अत्याहितं, उपप्लवः, अरिष्टं, अद्भुतं. 2 पूर्व-चिह्नं-लक्षणं. **–ous,** *a.* उत्पात-अनिष्ट-अशुभ-शंसिन्, अद्भुत; अत्याहित, औपसर्गिक-औत्पातिक-(की *f.*). **–ously,** *adv.* सोत्पातं, दुर्लक्षणपूर्वं.

Portfolio, *s.* पत्राधारः.

Porthole, *s.* नौपार्श्वछिद्रं.

Portico, *s.* *See* **Porch.**

Portion, *s.* अंशः, वि-,भागः, खंडः-डं, छेदः, शकलः-लं. 2 अंशः, वंटः, उद्धारः, वि-,भागः; 'p. of an estate' दायः, रिक्थभागः, उद्धारः; 'wife's p.' स्त्रीधनं, यौतकं, औद्वाहिकं. **–***v. t.* विभज् 1 U, वंट् 10, विभागशः क्लृप् c. 2 शुल्कं-वृत्तिं दा 3 U. **–ing,** *s.* विभागः, भागकल्पनं, वंटनं. **–less,** *a.* अनंश, अंशहीन.

Portly, *a.* गौरववति-वृत्ति, उदात्त, धीर, धीरदर्शन, गंभीराकृति. 2 स्थूल, बृहत्, स्थूलकाय, पृथूदर, पीन, पीवर. **–iness,** *s.* स्थूलकायत्वं, शरीरगौरवं.

Portmanteau, *s.* चर्ममंजूषा-पेटकः.

Portray, *v. t.* आ-,लिख् 6 U, चित्र् 10, वर्ण् 10. 2 उप-,वर्ण्, क्लृप् 10. **–Portrait,** *s.* चित्रं, आलेख्यं, प्रतिकृति *f.*, प्रतिमा; *See* **Picture;** 'p.-painter' चित्रक(का)रः.

Pose, *v. t.* स्तंभ् 9 P, मुह् c., निरुत्तरीकृ 8 U, कुंठ् 10.

Posit, *v. t.* प्रतिज्ञा 9 A, उपन्यस् 4 P.

Position, *s.* प्रतिज्ञा, उक्ति *f.*, हेतुः, पक्षः, उपन्यासः; 'wrong p.' पक्षाभासः, हेत्वाभासः. 2 स्थिति *f.*, स्थानं, पदं, आस्पदं, पद्धति-ती *f.* 3 प्रतिष्ठा, गौरवं. 4 अवस्था, दशा, आकारः, संस्थानं, भावः, वृत्ति *f.*; 'attain the p. of' पदं या 2 P, (यान्त्येवं गृहिणीपदं युवतयः S. 4); 'holding the p. of mistress of the house' गृहिणीपदभाज्, गृहिणीपदे स्थिता; 'give the p. of' पदं वह् c., भावं गम् c., (महिषीपदं प्रापिता, देवीभावं गमिता); 'p. in life' स्थितिः, निसर्गजातिः, अवस्थानं.

Positive, *a.* स्पष्ट, असंदिग्ध, अगूढ, प्रत्यक्ष, व्यक्त, अवक्र, परिस्फुट, साक्षात् *ind.*; 'reply in the p.' भवतु-बाढं-तथा-इति वद् 1 P. 2 अवश्यक, अवैकल्पिक (की *f.*), अविशंक्य; *See* **Peremptory.** 3 सु-,नियत, निश्चित, निर्णीत, निर्दिष्ट. 4 सत्य, तथ्य, यथार्थ, वास्तविक-तात्त्विक-(की *f.*). 5 विविक्त, केवल, अनन्यसंबद्ध. 6 दृढ-कृत-निश्चय, दृढमति-संकल्प, निर्विकल्प, निःसंदेह; मताभिमानिन्, स्वमताग्रहिन्, दृढोक्ति; 'a p. quantity' धनं (opposed to ऋणं, क्षयः, व्ययः, हानिः). **–ly,** *adv.* स्पष्टं, व्यक्तं, असंदिग्धं, साक्षात्. 2 अवश्यं, निर्विकल्पं, अविचार्य. 3 सुनिश्चितं, नियतं, नूनं, खलु. 4 वस्तुतः, तत्त्वतः, परमार्थतः, सत्यं, यथार्थतः. 5 सुनिश्चयेन, दृढनिश्चयपूर्वं. 6 मताग्रहेण, मताभिमानेन, दृढोक्त्या. **–ness,** *s.* स्पष्टता, असंदिग्धता, दृढनिश्चयः-निर्णयः, तत्त्वता, याथार्थ्यं, मताग्रहः, दृढोक्ति *f.*, &c.

Possess, *v. t.* धृ 1 P, 10, धा 3 U, भृ 3 U. 2 भुज् 7 U, अधि-ष्ठा 1 P, अध्यास् 2 A, सेव् 1 A; better by वत्, मत्, इन् &c.; *See* below. 3 आप् 5 P, लभ् 1 A, अधिगम् 1 P; *See* **Get.** 4 अधिकृ 8 U, प्रभू 1 P, अधि-ष्ठा, वशं कृ. 5 आविश् 6 P, आक्रम् 1 U, 4 P, उपसृज् 6 P, बाध् 1 A, उपहन् 2 P, ग्रस् 1 A, व्याप् 5 P, oft. ex. by 'p. ed.' **–ed,** *a.* धृत, भुक्त, अधिष्ठित, अध्यासित, अधीन, हस्तगत. 2 प्राप्त, लब्ध, अधिगत. 3 आविष्ट, आक्रांत, उपसृष्ट, ग्रस्त, उपहत. 4 (By spirits) भूताविष्ट, भूतोपसृष्ट, वेतालोपहत, भूतग्रस्त. 5 (Having) युक्त, युत, उपेत, संपन्न, उपपन्न, अन्वित, सनाथ, शालिन् in comp.; by वत्, मत्, इन्, विन् affixed, or by Bah. comp. **–ion,** *s.* भोगः, भुक्ति *f.*, अधिकारः, आवेशः, आक्रमः-मणं, आत्मसात्करणं; 'to take p. of' आक्रम्, आविश्, स्वायत्तीकृ, आत्मसात्कृ; पदं कृ or नि-धा; *See* **Enter;** 'to put in p.' अधिकृ c., अधिकारं दा, नियुज् 7 A, 10; 'being in one's p.' स्वायत्त, हस्तगत, वशवर्तिन्. 2 संपन्नता, युक्तत्वं, सना-

धनाः, वत्, शालिता in comp.; 'p. of wealth' धनवत्त्वं,सधनता.3 आवेशः,उपसर्गः, बाधा, पीडा; भूतावेशः, भूतपीडा-बाधा-संचारः. 4 द्रव्यं, स्वं वस्तु, स्वाधीनं द्रव्यं, (p.s) द्रव्यजातं, वस्तुजातं, द्रव्याणि, वस्तूनि; वित्तं, विभवः, द्रविणं, अर्थः, क्षेत्राणि, भूमि f., (landed). -ive, a. संबंध in comp.;'p. case' षष्ठी. -or, s. भोक्तृ m., भोगिन् m., स्वामिन् m., अधिकारिन् m, शाली-धारी-in comp.

Possible, a. शक्य, साध्य, संभाव्य; gen. ex. by pot. pass. part.; 'not p. to be united' दुःसंधेय; 'p. to be done' करणीय, संपाद्य, साध्य; oft. by शक् pass.; 'to be p.' संभू 1 P, (सर्वं सोढाभिन्नं संभाव्यते-Mal. 1), उपपद् 4 A, घट् 1 A; उभयथापि घटते (V. 3) 'it is p. in both ways' (both sides are p.); 'as far as p.' यावच्छक्यं, यथाशक्ति. -**Possibility,** s. संभवः, शक्यता, संभाव्यता, उपपत्ति f., घटना, संगति f. **Possibly,** adv. Ex. by शक्यं or शक् pass. 2 कदाचित्, कदापि, नाम, by pot. mood; *See* **Perhaps.** 3 (In questions) इव, नाम, वा; 'who p. that is dead, is not born again' मृतः को वा न जायते (P. I. 1).

Post, s. स्तंभः, स्थाणुः, स्थूणा, उपस्तंभः; 'p. for securing an elephant' आलानं, बंधस्तंभः; 'p. for tethering cattle' शिवकः, कीलकः, मेथिः-थिः, खलेवाल n. 2 पदं, अधिकारः, नियोगः, अधिकारपदं. 3 स्थानं, स्थलं, आस्पदं, अवस्थानं, स्थिति f., पदवी. 4 गुल्म-सैन्य-स्थानं. 5 पत्रवाहः, पत्रवाहनसाधनं; 'p.-boy' अश्ववाहः; 'p.-chaise' जवरथः-वाहनं; 'p.-haste' सवेगं, अतिजवेन, अश्ववत्; 'p.-horse' जवाश्वः, जवतुरगः; 'p.-man' पत्र or लेख-वाहः or हारः; 'p.-master' पत्रस्थानाधिकारिन् m., पत्रवाहाध्यक्षः; 'p. office' पत्रस्थानं-गृहं. -v. t. स्था c. (स्थापयति), सं-प्रति-°, नियुज् 7 A, 10. 2 स्तंभे बंध् 9 P. 3 पत्रस्थाने निविश् c. or क्षिप् 6 P. 4 प्रकाश् c., आसंज् c. -v. i. जवेन गम् or व्रज् 1 P; 'p. up' अवबुध् c.; 'p. off' व्याक्षिप् 6 P, विलंब् c. -age, s. पत्रवाहनमूल्यं. -er, s. जवनः, जवः, जवाश्वः, प्रजविन् m. -**Postilion,** s. जवाश्ववाहः

Post-date, v. t. पश्चात् तिथिं लिख् 6 P

Post-diluvian, a. प्रलयोत्तरकालीन.

Posterior, a. पश्चात्-उत्तर-कालीन, उत्तर, अपर, अवर, अर्वाच्. -ity, s. परता, उत्तरता. -ly, adv. पश्चात्, उत्तरं-रतः, परतः, परस्तात्. -**Posteriors,** s. नितंबः, गुदप्रदेशः.

Posterity, s. संतति f., अपत्यं, संतानः, वंशः, प्रजा, पुत्रपौत्रादयः.

Postern, s. पक्षद्वारं, पक्षकः.

Posthumous, a. मरणादूनंतरं प्रकाशित, मृत्यूत्तरजात.

Post-meridian, a. अपराह्णतन (नी f.) पराह्णकालिक (की f.).

Post-mortem, a. मरणोत्तर, मृत्यूत्तर.

Post-natal, a. जन्मोत्तर.

Post-nuptial, a. विवाहोत्तर, विवाहोत्तर्.

Postpone, v. t. व्याक्षिप् 6 P. विलंब् c., (नियतकालं यावत्) त्यज् 1 P, विसृज् 6 P. -ment, s. व्याक्षेपः, विलंबः.

Post-script, s. अनुलेखः.

Postulate, s. स्वीकृतपक्षः, गृहीतपदं, परिग्रहः. -v. t. परिग्रह् 9 P, स्वीकृ 8 U.

Posture, s. सं-,स्थिति f., संस्थानं, संस्था, अंगविन्यासः-स्थितिः; आसनं, बंधः; वीरासनं, कमलबंधः &c.; 'in a sitting p.' आसीन, उपविष्ट. 2 **Condition,** q. v.

Posy, s. कुसुमस्तबकः, पुष्पगुच्छः. 2 अंगुलीयकलेखः.

Pot, s. घटः, कलसः-शः, कुंभः, पात्रं, भाजनं, भांडं; 'cooking-p.' स्थाली, उखा, पिठपचनं, ऋजीषं, पिठरः; 'p.-bellied' तुंदिल, लंबोदर, पिचिंडिल, तुंदिन्; 'p.-belly' पिचिंडः, लंबोदरं; 'p.-companion' पानमित्रं-सुहृद्, सहपायिन् m. 'p.-house' शुंडा, पानं; 'p.-sherd' घटशकलं, भिन्नपात्रं. -ter, s. कुंभकारः, कुलालः, घटकारः, चक्रिन् m. -tery, s. कुंभ-घट-स्थानं. 2 कौलालकं, मार्तिकं, मृद्भांडानि.

Potable, a. पेय, पानीय, पानार्ह.

Potash, s. सर्जिका, क्षारः; *See* **Natron.**

Potation, s. पानं, सपीति f., दुरापानं.

Potato, s. गोलालुः.

Potent, a. प्रबल, समर्थ, वीर्यवत्, सप्रताप, शक्तिमत्, प्रभविष्णु; *See* **Strong.** -ate, s. अधिपतिः, नरेश्वरः, प्रभुः; *See* **King.** -ly, adv. प्रबलं, सप्रतापं, बलवत्.

Potential, a. शक्य, उपपन्न, संभवनीय; (mood) विधिलिङ्. -ity, s. शक्यता, संभाव्यता.

Pother, *See* **Bustle, Perplex.**

Potherb s, शाकः, हरितकं, शिग्रुः.

Potion, s. अगदः, पानं, पेयौषधं.

Pottage, s. यूषं.

Potulent, a. आमत्त. 2 पानयोग्य.

Pouch, s. स्यूतः, प्रसेवः, कोशः-षः. 2 लंबोदरं. 3 पेशि-शी, f., उपजठरं. -v. t. कोशे निविश् c. or नि-धा 3 U. [क्षिन् m.

Poulterer, s. वैतंसिकः, शौनिकः, पक्षिविक्र-

Poultice, s. उपनाहः, प्र-,लेपः. -v. t. उपनाहं कृ 3 U.

Poultry, s. गृहपक्षिणः; 'p.-yard' कुक्कुटस्थानं.

Pounce, *v. i.* अवपत्य ग्रह् 9 U, सहसा अवपत् 1 P or अवस्कन्द् 1 P or आक्रम् 1 U, 4 P. -*s.* नखः, नखरः. 2 मसीशोषणचूर्णं.

Pound, *s.* (For cattle) अवरोधः, अवरोधस्थानं, व्रजः, गोष्ठं. -*v. t.* सं-, चूर्ण् 10, मृद् 9 P, पिष् 7 P, क्षुद् 7 P, खंड् 10; ' p. to dust ' चूर्णशः कृ, चूर्णपेषंपिष्, चूर्णीकृ 8 U. 2(व्रजे) नि-अव-रुध् 7 U, or बंध् 9 P. 3 तड् 10, तुद् 6 P, प्रहृ 1 P. **-age,** *s.* शुल्कं, राजस्वं. **-er,** *s.* पेष्टृ *m.*, पेषणः. 2 मुसलः-लं, अयोग्रं, मुद्गरः. **-ing.** *s.* चूर्णनं, पेषणं, मर्दनं, खंडनं.

Pour, *v. t.* पत् c., नि-,सिच् 6 P, प्र-,स्रु c.; ' p. water in ' जलेन पू 3, 9 U, सिच्. 2 (Out, forth) प्र-निर्-मुच् 6 P, उत्-वि-सृज् 6 P, अवपत् c., अवसृ c., निःसृ c., उत्क्षिप् 6 P, उद्-वृ 6 P, उद्गॄ c., उद्वम् 1 P, वृष् 1 P, प्र-वि-कॄ 6 P; निर्धूष्, निर्गल् c.; ' which has p.ed out its watery contents ' :निर्गलिताम्बुगर्भः, पानीयरिक्तोदरः (घनः); ' p. out the water from the pot ' पात्रं जलरिक्तं कुरु; ' p. ed forth arrows' शरवृष्टिं मुमोच; ' p. one's soul to another ' अन्यस्मै स्वमनोगतं सर्वात्मना निविद् c. -*v. i.* स्रु 1 P, प्र-परि-°, प्र-,स्यंद् 1 A, श्च्युत् 1 A, जलं स्रु c. or प्रवृष् 1 P. 2 वृष्, निर्गल् 1 P. 3 निःसृ 1 P, निर्गम् 1 P, निःस्रु ' rain p. ed down in torrents ' धारासारैर्महती वृष्टिर्बभूव (H. 3); ' p. in upon ' समापत् 1 P, अभिद्रु 1 P, बहुशः आपत् or आक्रम् 1 U, 4 P. **-er,** *s.* स्रावकः, सेचकः, सेक्तृ *m.* **-ing,** *s.* सेकः, स्रावः, स्रवः, श्च्योतः

Pout. *v. i.* (क्रोधात्) ओष्ठौ प्रसृ c. or दृश् c. 2 उन्नत-उच्छ्रित-*a.* भू 1 P. -*s.* क्रोधावेशः.

Poverty, *See* under **Poor.**

Powder, *s.* चूर्णं, पिष्टं, क्षोदः; ' gun-p. ' आग्नेयचूर्णं; 'perfumed p.' वासयोगः, पिष्टातः-तकः, पटवासकः. -*v. t.* ' to reduce to p. ' चूर्ण् 10, क्षुद् 7 P, चूर्णीकृ, पिष् 7 P; *See* **Poond,** 2 चूर्णेन लिप् 6 P, or भू c. or मिश्र् 10. **-y,** *a.* पांसुल, चूर्णवत्, चूर्णमय (यी *f*), सचूर्ण, सक्षोद.

Power, *s.* शक्ति *f.*, सामर्थ्यं, बलं, प्रभावः, वीर्यं, ऊर्जः, सहस्-ओजस्-*n.*, विभवः (वाग्विभवः); (martial) तेजस् *n.*, वि-पराक्रमः, शौर्यं. 2 (Ability) शक्तिः, क्षमता, धीशक्तिः; ' p. of thinking ' विचारणाशक्तिः; 'according to one's p. ' यथाशक्ति-बलं, यावच्छक्यं. 3 (Influence) प्रभुत्वं, प्रभावः, वशः-शं, बलं, गौरवं, अधिकारः; आधिपत्यं, ईशत्वं, सत्ता, ऐश्वर्यं, अधीनता. 4 अधिपः-पतिः, अधीशः, प्रभुः. 5 (Legal) अधिकारः, or by अर्ह् 1 P. 6 अधिकारिजनः, अधिकृतः. 7 वातः. 8 सेना, बलं, पृतना, ' have or exercise p. over ' प्रभू 1 P, ईश् 2 A (with gen.), वशीकृ, आयत्तीकृ, आत्मवशं नी 1 P; in (under) the p. of' वश, अधीन, आयत्त, तंत्र in comp.; ' fallen into another's p.' परहस्तगत, ' to be in one's p.' ex. by शक् 5 P or by (*s.*). **-ful,** *a.* बल-सामर्थ्य-वत्, शक्त, बलिन् सबल, प्रबल, ऊर्जस्वल, ओजस्विन्, शक्तिमत्, ऊर्जितसत्त्व बलाढ्य, सप्रभाव, प्रभविष्णु. 2 शूर, वीर, विक्रांत, तेजस्विन्, महाप्रताप, प्रतापवत्, धामवत्, उग्रविक्रम. 3 (Medicine) वीर्यवत्, अमोघ, गुणावह, प्रबल, अलंतम. 4 दृढ, प्रतीतिकारिन्, प्रबल. **-fully,** *adv.* बलवत् प्रबलं, सप्रभावं, अत्यंतं. **-fulness,** *s.* प्राबल्यं, शक्तत्वं. **-less,** *a.* निर्बल. शक्तिहीन, अशक्त, अबल, निष्प्रभाव, असमर्थ, अक्षम. **-lessness.** *s.* अशक्ति *f.*, असामर्थ्यं.

Pox, *s.* **Small-pox,** q. v. 2 उपदंशः.

Practice, *s.* प्र-आ-चारः, संप्रदायः, व्यवहारः, रीति *f.*, मार्गः, पद्धति *f.*, क्रमः, वृत्तिः *f.* 2 अभ्यासः, क्रिया-प्रबंध-सातत्यं, नित्यवृत्तिः, चर्या-अनुष्ठानं, अनुशीलनं, निरंतरप्रवृत्तिः, आवृत्तिः; 'does not require p.' नाभ्यासक्रममीक्षते. 3 क्रिया, आचारः, आचरणं, कर्मन् *n.* कृति *f.*, व्यापारः, व्यवसायः; करणं, विधानं, अनुष्ठानं; (execution) प्रवृत्तिः, प्रचारः; व्यवहारः; ' bring or put into p. ' प्रवृत् c., व्यवहृ c.; ' has long been in p. ' चिरप्रवृत्त. 4 (Opp. of theory) प्रयोगः. 5 छलं, व्याजः, कैतवं; *See* **Fraud;** 'ancient p. ' वृद्धाचारः, वृद्धपरंपरा; ' family p. कुलसंप्रदायः, कुलधर्मः, कुलाचारः; ' local p. ' देशाचारः; ' good p. ' सदाचारः; 'following good p. s' सदाचार, सद्वृत्ति, सद्वृत्त; साधुवृत्त; 'bad p.' दुराचारः, कुमार्गः, दुर्वृत्तिः; ' following bad p. s' दुर्वृत्त, दुराचार; ' p. of medicine ' वैद्यक्रिया-उपचारः, चिकित्सा, भेषजप्रयोगः, उपक्रमः; ' p. of arms ' शस्त्राभ्यासः, शस्त्रचर्या; ' p. of law ' व्यवहारः, व्यवहाराभ्यासः; ' p. in archery' शराभ्यासः, उपासनं. **-Practise,** *v. t.* अभ्यस् 4 U, नित्यं कृ 8 U, &c. 2 आचर् 1 P, अनुष्ठा 1 P, कृ, वि-धा 3 U, आ-स्था 1 U. 3 प्र-उप-युज् 7 A, 10, प्रवृत् c., व्यवहृ c., सेव् 1A, आश्रि 1 U, आ-अवलंब् 1 A; 'what profession do you p. ' कां वृत्तिमुपजीवत्यार्यः (Mr. 2). -*v. i.* शाठ्येन आचर् or व्यवहृ 1 P, छलं-कपटं-कृ. **-ed,** *a.* अभ्यस्त, आचरित, अनुष्ठित, कृत, सेवित, &c. 2 अभिज्ञ, परिचयवत्, बहुदृष्ट, व्यवहारज्ञ, दृष्टकर्मन्, पक्वबुद्धि, ज्ञानवृद्ध, जाताभ्यास; also ex. by (*s.*). **-ing,** *a.* अभ्या-

सिन्, सेविन्, शालिन्, in comp.: आस्थित, आश्रित. -**Practicable,** *a.* करणीय, कर्तुं शक्य, साध्य, संभाव्य, शक्य, सुकर, सुख-साध्य, उपपाद्य. -**Practical,** *a.* अभ्यासिक-व्यवहारिक-(की *f.*), अभ्याससिद्ध-प्राप्त, आचार-व्यवहार in comp.; 'p. knowledge व्यवहारज्ञानं, लौकिकज्ञानं. 2 अभ्यासक्षम, व्यवहार्य, प्रयोज्य, प्रवर्तनीय, व्यवहारोचित; 'a p. scheme' व्यवहारोचित उपायः; 'he is a p. teacher' स शिक्षणप्रयोगनिपुणः. 3 व्यवहारज्ञ, दृष्टकर्मन्. अभिज्ञ; *See* **Practised.** -**ly,** *adv.* कार्यतः, अर्थतः, वस्तुतः, परमार्थतः, व्यवहारतः, फलापेक्षया. 2 अभ्यासेन, व्यवहारेण. **Practitioner,** *s.* सेविन्, व्यवसायिन् *m.* व्यापारिन् *m.* वृत्ति, आजीव in comp. 2 वैद्यः, वैद्यवृत्तिः, चिकित्सकः 3 व्यवहारज्ञः, व्यवहारदर्शिन् *m.*-निपुणः.

Pragmatic, -al, *a.* परकार्यचर्चक, अनधिकारव्यापारिन्; *See* **Meddle,** &c.

Praise, *v. t.* प्रशंस् 1 P, श्लाघ् 1 A, ईड् 2 A, नु 2 P, स्तु 2 U, वर्ण् 10, गै 1 P, कृत् 10, वि-प्र-° ख्या 2 P or c. (ख्यापयति), पन् 1 P, नू 6 P. -*s.* प्र-,शंसा, श्लाघा, स्तुति *f.*, स्तवः, वर्णनं-ना, कीर्तनं, नुति *f.*, ईडा, स्तोत्रं. -**er,** *s.* प्रशंसकः, स्तावकः, वर्णकः, वैतालिकः. -**Praiseworthy,** *a.* प्रशस्य, प्रशंसार्ह, श्लाघ्य, स्तुत्य.

Prance, *v. i.* प्लु 1 A, वल्ग् 1 P, नृत् 4 P. -**ing,** *s.* प्लुतं, वल्गितं, प्लवनं.

Prank, *s.* क्रीडा, चेष्टा, चापलं, लीला, छंदः-वृत्त् *n.*; 'idle p.' वानर or मर्कट-चेष्टा or क्रीडा; 'mischievous p.' कु-दुः-चेष्टितं. -*v. t.* दंभार्थं भूष् 10 or अलंकृ 8 U. -**ish,** *a.* कुचेष्ट, चपल, क्रीडाशील.

Prate, Prattle, *v. i.* प्र-,लप् 1 P, प्र-,जल्प् 1 P, अनर्थकं वद् 1 P or भाष् 1 A. -**er,** *s.* वाचाटः, वाचालः, जल्प (ल्पा)कः, वावदूकः, बहुभाषिन् *m.* -**ing,** *s.* प्रलापः, प्रलपितं, प्र-, जल्पः-ल्पितं-ल्पनं; बालालापः, बालभाषणं-प्रलापः.

Pravity, *s.* भ्रष्टता, विक्रिया, विकारः.

Pray, *v.* (A deity) स्तु 2 U, प्र-अभि-सं-°, नमस्यति (D.), अभिवद् c., आराध् c., प्रणम् 1 P; (मनसा) पूज् 10, उपास् 2 A, ध्यै 1 P, चिंत् 10. 2 आशंस् 1 A. 3 याच् 1 A, प्र-अभि-अर्थ् 10 A; वि-ज्ञा c. (ज्ञापयति), gen. ex. by अर्ह् 1 P with inf.; *See* **Please;** 'I p. you tell me' मह्यं कथयितुमर्हति भवान्. 4 (Lowly) जप् 1 P. -**er,** *s.* स्तवः, स्तोत्रं, प्रार्थना-नं, नमस्या, उपासना, पूजा; (mental) ध्यानं, आवाहनं; (low) जपः, स्वाध्यायः. 2 याच्ञा, प्रार्थना, अभ्यर्थना, विज्ञप्ति *f.*, विज्ञापना. -**ful,** *a.* प्रार्थनाशील, भजनपरायण.

Preach, *v. t.* उदीर् c., उद्-घुष् 10, उच्चर् c, प्र ख्या c. (ख्यापयति), प्रकाश् c., प्रवद् 1 P, कृत् 10. -*v. i.* धर्मं प्रवच् 2 P or शास् 2 P or उपदिश् 6 P. -**er,** *s.* उपदेशकः, प्रवक्तृ *m.*, प्रचारकः, धर्मशासकः, धर्मोपदेशिन् *m.* 2 घोषकः, प्रख्यापकः. -**ing,** *s.* वि-,घोषणं-णा, प्रख्यापनं, धर्मोपदेशः, धर्मशासनं, प्रवचनं, उपदेशः.

Preamble, *s.* उपोद्घातः; *See* **Introduction.**

Prebend, *s.* *See* **Canon.**

Precarious, *a.* संदिग्ध, अनिश्चित, अनिर्णीत, अनियत, अस्थिर, अध्रुव. 2 पराधीन, परायत्त, अस्वतंत्र; *See* **Doubtful, Dangerous.** -**ly,** *adv.* संदिग्धं, अनियतं. -**ness.** *s.* अनियतत्वं, अन्याधीनता.

Precative, Precatory, *a.* याचक, प्रार्थनात्मक; 'p. mood' आशिर्लिङ्.

Precaution, *s.* पूर्वोपायः, निवारणोपायः, पूर्व-समीक्षा-चिंता, पूर्वावधानं, पूर्वप्रबोधः; 'take p. s' पूर्वमेव उपायं समीक्ष् 1 A or चिंत् 10; 'hence I give you this p.' अतस्त्वामेवं प्रबोधयामि. -**ary,** *a.* पूर्वोपायरूप, by (*s.*).

Precede, *v. t.* पूर्वं-अग्रे-पुरतः गम्-सृ-चर् 1 P or इ-या 2 P or वृत् 1 A or स्था 1 P; oft. ex. by पूर्वं, प्राक्, प्रथमं, ततः, अनंतरं; 'the flower p. s the fruit' उदेति पूर्वं कुसुमं ततः फलं, so घनोदयः प्राक् तदनंतरं पयः (S. 7.); 'visarga p. ed by अ' अपूर्वः विसर्गः; 'many kings p. ed Rāma' रामात् पूर्वं बहवो नृपाः समजायंत. 2 (In rank) अग्रपदे वृत्, अग्रमानं अर्ह् 1 P. -**ence,** *s.* अग्रगमनं, पुरःसरणं. 2 अग्र- श्रेष्ठ-पदं, पुरस्कारः, उत्कर्षः, प्राधान्यं, अग्रत्वं, अग्रणीत्वं, आग्रमानः-पूजा, मुख्यता, श्रेष्ठत्वं, प्राधान्यं. -**ent,** *s.* (पूर्वं) निदर्शनं, उदाहरणं, आदर्शः, प्रतिमा, प्रमाणं, दृष्टांतः; 'having no p.' अप्रतिम. -*a.*, -**ing,** *a.* पूर्व-अग्र गामिन्, अग्रग, पूर्वग, पूर्व, अग्र, प्रथम, अग्रे-पुरः-सर. -**ented,** *a.* भूत-दृष्ट-पूर्व, दृष्टप्रतिम; 'un.-p.' अप्रतिरूप, निरुपम, अतुल.

Precentor, *s.* मुख्यगायकः, गायकाग्रणीः.

Precept, *s.* नियोगः, आ-नि-देशः, अनु-, शासनं, अनुज्ञा, विधिः, नियमः, प्र-,चोदनं-ना, कल्पः, आज्ञा, स्थिति *f.*, मर्यादा. 2 वचनं, उपदेशः; 'moral p. s' नीतिवचनानि; 'religious p.' धर्माज्ञा, धर्मशासनं; 'example is better than p.' शासनात् करणं श्रेयः, वाचः कर्मातिरिच्यते. -**ial, -ive,** *a.* वैधिक-नैयमिक-(की *f.*), विधिरूप, (*s.*) in comp. -**or,** *s.* गुरुः, शिक्षकः, उपदेशकः, आचार्यः, अध्यापकः, उपाध्यायः.

Precession, *s.* अग्रगति *f.*; 'p. of the equinoxes' अयनचलनं, क्रांतिपातगति *f.*

Precinct, *s.* सीमा, पर्यंतः, मर्यादा, अवधिः, परिसरः उपांतं, उपकंठं, समंतदेशः.

Precious, *a.* महार्ह-र्घ, महा-बहु-मूल्य, अनर्घ, अमूल्य, उत्कृष्ट, बहुमत, प्रिय, परम; 'p. stone' उपलरत्नं, अमूल्यरत्नं, रत्नं, मणिः. **-ness,** *s.* महार्घता, बहुमूल्यं.

Precipice, *s.* प्रपातः, भृगुः, अतटः. **-Precipitous,** *a.* पातुक, विषम, प्रवण, अवसर्पिन्. 2 **Rash,** q. v.

Precipitate, (**Precipitant,**) *a.* अवाङ्मुख (खी *f.*), अधोमुख, अवाक्‌शिरस्. 2 असमीक्ष्य-क्षिप्र-अविमृश्य-कारिन्, साहसिन्, साहसिक (की *f.*); (act) सरभस, अविमृष्ट, अतिक्षिप्र, साहस in comp. **-v.** *t.* रभसा अधः क्षिप् 6 P or पत् c. 2 सरभसं प्रवृत् c. or प्रोत्सह् c., त्वर् c. (त्वरयति). **-v.** *i.* अव-अधः-पत् 1 P, नि-सद् 1 P. 2 (Fig.) अविचार्य-सरभसं-व्यापृ 6 A or c. **-ly,** *adv.* अवाक्, अवाक्‌शिरसा, अधोमुखेन. 2 अविमृश्य, असमीक्ष्य, सहसा, साहसेन, अतिक्षिप्रं, सरभसं. **-ion,-ness,** *s.* अधःपातनं-क्षेपणं, अवपातनं. 2 साहसं, साहसिकता, क्षिप्रकारिता, असमीक्ष्य-अविमृश्य-कारिता. **Precipitance,** *s.* साहसं; *See* above.

Precis, *s.* सारः, संक्षेपः, संग्रहः.

Precise, *s.* नियत, निर्दिष्ट, निश्चित, परिच्छिन्न, यथार्थ, विशेष in comp.; *See* **Exact.** 2 व्यक्त, स्फुट, सूक्ष्म. 3 (Of persons) ...नियमिक (की *f.*), समयानुवर्तिन्, संकेतानुरोधिन्, सूक्ष्मनियमनिष्ठ. **-ly,** *adv.* नियतं, यथार्थं, सूक्ष्मतया; oft. by एव; 'at noon p.' मध्याह्नसमये एव; 'p. so' एवमेव. **-ion,-ness,** *s.* नियतत्वं, निर्देशः, सूक्ष्मता, सुनिश्चितता, याथार्थ्यं, व्यक्तता, &c.

Preclude, *v. t.* निवृ c., नि-प्रति-षिध् 1 P, नि-प्रति-रुध् 7 U, बाध् 1 A, प्रतिबंध् 9 P; *See* **Obstruct.** **-Preclusion,** *s.* प्रतिबंधः, निवारणं, नि-प्रति-षेधः; निरोधः. **-Preclusive,** *a.* निवारक, प्रतिबंधक, निरोधक.

Precocious, *a.* अकालपक्व-परिणत-प्रौढ. 2 बालप्रौढ-पक्व. **-ness,** **-Precocity,** *s.* अकालपरिणति *f.* -प्रौढता, बालप्रौढि *f.*

Precogitate, *v. t.* पूर्व-अग्रे चिंत् 10 or विचर् c. or विमृश् 6 P.

Precognition, *s.* पूर्वज्ञानं-बोधः.

Preconceive, Preconcert, *v. t.* पूर्वं चिंत् 10 or क्लृप् c. or नि-धृ c. **-ed,** *a.* पूर्वकल्पित-निर्धारित, पूर्वघटित-निर्णीत. **-ion,** *s.* अग्र-पूर्व-कल्पना-बोधः-ज्ञानं; पूर्वघटनं-संकेतः.

Precursor, *s.* पूर्वगः अग्रेसरः, अग्रयायिन् *m.* पुरःसरः; *See* **Harbinger,** 2 पूर्वलक्षणं-चिह्नं-लिंगं. **-y,** *a.* पूर्वग, पुरःसर, अग्रवर्तिन्.

Predatory, *a.* दस्युवृत्ति, अपहारक, उपप्लविन्, लुंठक, चौर in comp.

Predecessor, *s.* पूर्वगः, पूर्वाधिकारिन् *m.*

Predestinate, Predestine, *v. t.* पूर्व-अग्रे-निरूप् 10 or प्रकल्प् c. or निर्दिश् 6 P. **-ed,** *a.* अग्र or पूर्व-निर्दिष्ट or निरूपित, भाविन्, दैवाधीन, दैवायत्त, दैविक (की *f.*). **-ion,** *s.* अग्रनिरूपणं-निर्देशः. 2 दैववादः, दैवपरता, अदृष्ट-प्रारब्ध-वादः, दैविकता. **-Predestinarian,** *s.*: दैवपरः, दैव-अदृष्ट-वादिन् *m.* पञ्चविध्यः, दैवायत्तः, दैविकः.

Predetermine, *v. t.* पूर्व-अग्रे-निश्चि 5 U or निर्णी 1 P. **-ate,-ed,** *a.* पूर्वनिश्चित-निर्णीत. **-ation,** *s.* पूर्व-अग्र-निश्चयः-संकल्पः-निर्णयः.

Predial, *a.* क्षेत्र, भूमि in comp.

Predicament, *s.* पदार्थः; वर्गः, जाति *f.* 2 अवस्था, दशा, वृत्ति *f.*, भावः, स्थिति *f.*; कष्टावस्था, दुःस्थितिः, कृच्छ्रं.

Predicate, *v. t.* उद्दिश्य वद् 1 P or वच् 2 P or कथ् 10 or अभि-धा 3 U; विशिष् 7 P or c., वि-धा, निर्दिश् 6 P. **-s.** विधेयं, वाच्यं, विशेषणं. **-ion,** *s.* विधानं, विशेषणं, निर्देशः, अभिधानं. **-Predicable,** *a.* वाच्य, अभिधेय.

Predict, *v. t.* पूर्व-अग्रे-कथ् 10 or वच् 2 P or निरूप् 10, आ-समा-दिश् 6 P; कथ्, वद् 1 P, with words for 'Future,' q. v.; 'p. ed that she would be the sole wife of Hara' तां समादिदेशैकवधूं भवित्रीं...हरस्य (K. I. 51); कथयत्यागामिनमत्ययं (Ka. 46) 'p. s (unforeseen) events'. **-ion,** *s.* अनागतकथनं, भाविकथनं, आ-समा-देशः, भविष्यद्वाक्. **-or,** *s.* पूर्ववादिन् *m.* अग्रनिरूपकः, सिद्धः, आदेष्टृ *m.*

Predilection, *s.* पक्षपातः, पूर्वग्रहः, अनुरागः; *See* **Partiality.**

Predispose, *v. t.* पूर्वं प्रवृत् c. or प्र-उद्-युज् 7 A, 10, प्रवणीकृ 8 U; ex. by प्रवण, उद्यत, उन्मुख, शील in comp.; 'p. ed to anger' क्रोध-प्रवण-शील. **-ition,** *s.* प्रावण्यं, प्रवृत्ति *f.*, शीलं.

Predominate, *v. i.* प्र-भू 1 P, प्रबल-अधिक-बलीयस्-*a.* भू 1 P, अतिरिच्-विशिष्-pass.; *See* **Excel.** **-Predominant,** *a.* प्रबल, अतिरिक्त, प्रधान, विशिष्ट, अधिक, प्रभविष्णु. **-ly,** *adv.* प्राधान्येन, प्रबलं, विशिष्टतया. **-Predominance,** *a.* प्राबल्यं, प्राधान्यं, आधिक्यं, अतिरेकः.

Pre-eminent, *a.* सर्वप्रधान, श्रेष्ठ, सर्वोत्कृष्ट, अग्रगण्य, परम, उत्तम, विशिष्ट, प्रमुख, अग्रणी, अग्रिय, वरेण्य; oft. by व्याघ्रः, शार्दूलः, पुंगवः, ऋषभः, मुकुटः, &c. in comp.; *See* **Excellent.** **-ly,** *adv.* परमं, प्राधान्यतः, विशिष्टं, सातिशयं, अत्यर्थं, सविशेषं

-**Pre-eminence**, *s.* उत्कर्षः, प्राधान्यं, प्रमुखता, श्रेष्ठता, उत्तमता, अग्रगण्यत्वं, वैशिष्ट्यं.

Pre-emption, *s.* पूर्वक्रयः, पूर्वक्रयाधिकारः.

Pre-engage, *v. t.* पूर्वं प्रतिज्ञा 9 A, पूर्वं संक्लृप् c. -**ment**, *s.* पूर्वसंकेतः-प्रतिज्ञा.

Pre-exist, *v. i.* पूर्वं भू 1 P ('Be' q. v.) -**ence**, *s.* प्राग्भावः-जन्मन् *n.*-जीवनं. -**ent**, *a.* पूर्वभव-भूत.

Preface, *s.* आमुखं, प्रस्तावना, मुखबंधः, उपोद्घातः, वाङ्मुखं, उपन्यासः, प्रारंभः. -*v. t.* प्रस्तु 2 U, प्रस्तावनां लिख् 6 P or कृ 8 U. -**Prefatory**, *a.* प्रस्तावना-उपोद्घात-रूप.

Prefer, *v. t.* उन्नम् c. (नमयति), उत्कर्षं नी 1 P or प्राप् c., पुरस्कृ 8 U, उत्कृष्टपदे नियुज् 7 A, 10, प्रतिपत्तिं प्राप् c. 2 अधिकं रुच् 1 A or मन् 4 A or c. or प्रतीक्ष् 1 P; वृ 5 U or 10, (वरयति); gen. ex. by वरं-न with पुनः, च, तथापि; 'I p. death to disgrace': वरं मृत्युः न पुनरपमानः; वरं वंध्या भार्या न चाविद्वान् तनयः &c. 3 सम्-ऋ c. (अर्पयति), निविद् c., उपहृ 1 P; See Offer. -**able**, *a.* वरीयस्, श्रेयस्, प्रियतर; better ex. by (*v.*). -**ence**, *s.* अभिरुचिः *f.*, अधिकानुरागः. 2 आदराधिक्यं, अधिकमानः; 'in p. to' विहाय, अतीत्य, अपेक्षया in comp. -**ment**, *s.* उन्नतिः *f.*, पदोत्कर्षः, प्रतिपत्तिः *f.*, उत्कर्षः; स्थानोन्नतिः, प्रतिष्ठापदं, गौरवास्पदं.

Prefigure, *v. t.* प्रतिबिंबं दृश् c. -**ation**, *s.* पूर्वलक्षण-दर्शनं.

Prefix, *s.* उपसर्गः. -*v. t.* पूर्वं आ-प्र-युज् 7 A, 10, पूर्वं-अग्रे-विन्यस् 4 U or नि-आ-धा 3 U or लिख् 6 P.

Pregnant, *a.* गर्भिणी, गर्भवती, सगर्भा, अंतर्वत्नी, आपन्नसत्त्वा, ससत्त्वा, धृत-संजात-गृहीत-गर्भा, गर्भधारिणी; 'to be p.' गर्भं-आधा 3 U or धृ 1 P, 10, भृ 1 P with (*a.*); 'a p. woman longing for things' श्रद्धालुः, दोहदवती. 2 अर्थयुक्त-गर्भ. 3 सं-परि-पूर्ण-व्याप्त-गर्भ in comp. -**Pregnancy**, *s.* गर्भः, दौर्हृदं, गर्भधारणं-ग्रहणं, प्र-[illegible] 'showed signs of p.' दौर्हृदलक्षणं [illegible] (R. III. 1); 'advanced in p. [illegible]र्भा.

Prehistoric, *a.* प्राक्-पौराणिक-कालीन.

Prejudge, *v.* पूर्वं निर्णी 1 P or विचर् c. or निर्णी 5 U. -**ment**, *s.* पूर्वनिर्णयः-निश्चयः.

Prejudicate, *See* **Prejudge**.

Prejudice, *s.* दुराग्रहः, आ-,ग्रहः, चेतोविकारः-विक्रिया, वक्रीभावः; अविचारमतिः *f.*, अविचारपूर्वः निर्णयः. 2 पक्षपातः, संगः. 3 नाशः, क्षतिः *f.*, हानिः *f.*, अपायः, अपकारः; *See* **Harm**. -*v. t.* विकृ 8 U, साचीकृ, आवृज् 10, पूर्वं प्रवृत् c. 2 अपकृ, नश् c., क्षण् 8 P; *See* **Injure**. -**ial**, *a.* हानि-अपकार (री *f.*), अहित, अननुकूल, अपकारक. -**ially**, *adv.* सापायं, सापकारं.

Pre-knowledge, *s.* पूर्वज्ञानं-बोधः.

Prelate, *s.* *See* **Bishop**.

Prelect, *v. t.* प्र-वच् 2 P, प्र-पठ् c. -**ion**, *s.* *See* **Lecture**.

Prelibation, *s.* पूर्वास्वादः, पूर्वभुक्तिः *f.*

Preliminary, *a.* पूर्व-आदि-प्रथम in comp.; प्राथमिक (की *f.*). 2 पारिभाषिक (की *f.*), प्रस्तावनारूप. -*s.* (pl.) पूर्वकार्याणि, पूर्वविषयः. 2 Preface, Introduction, q. v.

Prelude, *s.* प्रस्तावना, आमुखं, पूर्वरंगः. 2 आ-प्रारंभः, उपक्रमः. -*v. t.* प्रस्तु 2 U, प्रारभ् 1 A, उपक्रम् 1 A.

Premature, *a.* अकालपरिणत-पक्व, अपूर्णकाल, अपूर्णकालज, असामयिक-अ(आ)कालिक-(की *f.*), अकाल-असमय in comp.; 'p. death' अकालमृत्युः. 2 साहसिक, अकालसह; *See* **Rash**. -**ly**, *adv.* अपूर्णकाले, अकाले, असमये; 'p. born' अपूर्णकालज; 'p. bald' युवखलतिः. -**ness**, *s.* अकालिकत्वं.

Premeditate, *v. i.* पूर्वं संक्लृप् c. or विचर् c. or चिंत् 10. -**ed**, *a.* पूर्वसंकल्पित-चिंतित, मति-बुद्धि-पूर्व, सांकल्पिक-सांकेतिक-(की *f.*), बुद्धिकृत. -**ion**, *s.* पूर्वसंकल्पः-विचारः-घटना.

Premier, *s.* प्रधानामात्यः, मुख्यमंत्रिन् *m.*, प्रधानसचिवः. -*a.* प्रधान, मुख्य, प्रमुख. -**ship**, *s.* प्रधानमंत्रिपदं.

Premise, *v. t.* उपन्यस् 4 U, उपक्षिप् 6 P, पूर्वं कथ् 10 or ब्रू 2 U or वद् 1 P, प्रस्तु 2 U or c., प्रस्तावनारूपेण कथ् or ख्या 2 P, प्र-उप-क्रम् 1 A. -*s.*, -**Premiss**, *s.* पक्षः, प्रतिज्ञा; 'major p.' उदाहरणं; 'minor p.' उपनयः. -**Premises**, *s.* गृहक्षेत्रादि, गृहपरिसरः.

Premium, *s.* लाभः, फलं, अधिकमूल्यं, पारितोषिकं.

Premonish, *v. t.* पूर्वं सूच् 10 or उपदिश् 6 P, प्रबुध् c. -**Premonition**, *s.* पूर्वबोधः, प्रबोधनं. -**Premonitory**, *a.* पूर्वबोधक, प्रबोधक.

Preoccupy, *v. t.* पूर्वं ग्रह् 9 U or भुज् 7 A or आक्रम् 1 U, 4 P. -**ation**, *s.* पूर्वभोगः-आक्रमः.

Preordain, *v. t.* पूर्वं प्रक्लृप् c. or निर्दिश् 6 P.

Prepare, *v. t.* प्र-उप-परि-क्लृप् c., सज्जीकृ 8 U, सं-,विधा 3 U, निर्मा 3 A, 2 P, रच् c. (रचयति), उप-प्र-युज् 7 A, 10 (medicines); संधा 1, 3 U, उपकरणद्रव्यैः संयुज्; oft. by कृ; (food) प्रसाध् c., सिध् c. (साधयति),

संस्कृ, पच् 1 P, विरचय् c.; (army 4 P or c., आयुधैः उपकल्पय् c.; (a book &c.) ग्रथ् 1 P, निर्मा, प्र-नि-बंध् 9 P, वि-,रच् 10; (lesson) शिक्ष् 1 A, पठ् 1 P, अधि-इ 2 A, पारं गम् 1 P; दृ 1 P (p. well). -v. i. उपकरणानि-द्रव्याणि-संभृ or कल्पय् c. 2 सज्जीभू 1 P, उद्यत-उद्युक्त-सज्ज-सिद्ध- a. भू. -ation, s. उपकल्पनं, योजनं, साधनं, विधानं, सज्जीकरणं, वि-,रचनं-ना, करणं. 2 संभारः, संविधा, संविधानं, सिद्धि f., सिद्धता, सामग्री; 'marriage-p. s' विवाहसंभाराः; 'war-p.s.' युद्धसामग्री; तदुत्तिष्ठ गच्छावो गमनसंविधानाय वत्सस्य (Ka. 294) 'come, let us go to make p. s' &c. 3 योगः. 4 संस्कारः, निष्पत्ति f., सिद्धि f. -ative,-atory, a. उपक्रमोपकारिन्, उपक्रमानुकूल; उपकल्पक, प्रथम, आद्य. -s. उपक्रमसाधनं, सिद्धिसाधनं, better ex. by (v. t.). -ed, a. कृत, निर्मित, घटित, रचित, उपकल्पित, कल्पित, निष्पन्न, &c. 2 सिद्ध, सन्नद्ध, सज्ज, उद्यत, उद्युक्त. -edness, s. सिद्धता, सज्जता. -er, s. उपकल्पकः, साधकः, रचकः, संस्कर्तृ m.

Pre-payment, s. पूर्वदानं-शोधनं.

Prepense, a. चिंतितपूर्व, मतिपूर्व; *See* **Premeditated**; 'malice p.' द्रोहचिंता.

Preponderate, v. i. अतिरिच्-विशिष्-pass., भारेण-गौरवेण-अतिरिच् or वृध् 1 A, प्र-भू 1 P, अधिक-गुरुतर-a. भू. -**Preponderance**, s. आधिक्यं, अतिरेकः, प्राबल्यं, प्राधान्यं, प्रभावः, गौरवं. 2 अधिकभारः, भाराधिक्यं.

Preposition, s. उपसर्गः. -al, a. औपसर्गि-(की f.).

Prepossess, v. t. (चित्तं) आवृज् 10, गृहीकृ 8 U, आकृष् 1 P, साधीकृ. 2 पूर्वं अधि-ष्ठा 1 P or युज् 7 A. -ed, a. (सद्यः) आकृष्टचित्त, सक्त, जातानुराग. -ing, a. (सद्यः) हृदयग्राहिन्, चित्ताकर्षिन् -ion, s. पक्षपातः, संगः, ग्रहः, प्रावण्यं, चित्ताकर्षणं. 2 पूर्वभोगः.

Preposterous, a. विपरीतक्रम, विपर्यस्त. 2 (अतीव) अयुक्त, असंगत, अनुपपन्न, असंबद्ध, अनर्थक. -ly, adv. अयुक्तं, असंगतं. -ness, s. वैपरीत्यं, क्रमविपर्ययः, अयुक्तता, असंगति f., असंबंधः.

Prepuce, s. शिश्नाग्रत्वच् f.

Pre-requisite, a. पूर्वाकांक्षित. -s. पूर्वाकांक्षा.

Prerogative, s. असाधारणाधिकारः, विशेषाधिकारः, विशेषशक्ति f., सत्ता.

Presage, v. t. पूर्वं सूच् 10 or आदिश् 6 P; *See* **Forebode**, **Predict**. -s. पूर्वसूचनं-ना, पूर्वलक्षणं-चिह्नं; *See* **Omen**.

Prescience, s. पूर्वज्ञानं, भविष्यद्विज्ञानं, भावि-अनागत-ज्ञानं, सार्वज्ञ्यं. -**Prescient**, a. भाविज्ञानिन्, अनागतवेदिन्; gen. ex. by पूर्वं ज्ञा 9 U or बुध् 1 P.

Prescribe, v. t. निर्दिश् 6 P, वि-धा 3 U, प्रकल्पय् c., प्र-चुद् 10, शास् 2 P, आ-ज्ञा c. (ज्ञापयति), नियम् 1 P. -ed, a. निर्दिष्ट, विहित, प्र-,चोदित, विध्यनुरूप, वैधिक, (की f.). -er, s. निर्देशकः, शास्तृ m. -**Prescript**, s. आदेशः, विधिः, आज्ञा, चोदनं-ना. -a. निर्दिष्ट, प्रकल्पित. -ion, s. कल्पः योगः, अगदनिर्देशः, उपचार-औषध-विधिः. 2 विधिः, निर्देशः, आज्ञा, प्र-,चोदनं-ना, शासनं, वचनं. 3 चिर or बहुकाल-भोगः or भुक्ति f., अनादिपरंपरा, अस्मार्तभोगः -ive, a. चिरकालभुक्त, अनादिपरंपरागत, चिरव्यवहारसिद्ध.

Present, v. t. उपहृ 1 P, उपहारं दा 3 U, प्र-उप-दा 3 U, ऋ c. (अर्पयति), विहृ 1 P, नि-अर्प् 10, उपढौक् c., प्रति-पद् c., (oblation) निर्वप् 1 P, निविद् c., उत्सृज् 1 P; *See* **Offer**. 2 उपन्यस् 4 P, उपक्षिप् 6 P, पुरो निधा 3 U. 3 (oneself) आविर्भू 1 P, उप-स्था 1 P, प्रादुर्भू, दृश्-लक्ष्-pass., प्रविश् 6 P, आत्मानं दृश् c. 4 दर्शनं कृ c., प्रविश् c.; दृश् c., पुरस्कृ 8 U, समक्षं नी 1 P; सकाशं नी; 'p. me to the king' मां राजदर्शनं कारय. 5 प्रदृश् c., आविष्कृ, व्यंज् 7 P or c., प्रकटयति (D.), प्रकटीकृ, सूच् 10; oft. ex. by **Appear** q. v.; 'the court p. ed a gay scene' अधिकरणमंडपः सुतरां रमणीयो बभौ, रम्यालोक आसीत्; 'what a charming sight do these girls p.' अहो मधुरमासां (कन्यकानां) दर्शनं (S. 1), अहो मनोज्ञदर्शनः कन्यकाजनः; 'p. an appearance of' विडंब् 10, अनुकृ (with gen.). -a. प्रस्तुत, प्रकृत. 2 (Mind) सावधान, अभ्रांत, अव्यग्र, अशून्य, समाहित, अव्याकुल, निराकुल, असंभ्रम, प्रत्युत्पन्न. 3 विद्यमान, वर्तमान, आधुनिक-सांप्रतिक-(की f.), अद्यतन-इदानींतन-(नी f.). 4 सद्यस्क, तात्कालिक (की f.); अविलंबित; 'in the p. state' अस्यामवस्थायां; 'at p.', 'for the p. time' अधुना, सांप्रतं, इदानीं; *See* **Now**. 5 उपस्थित, संनिहित, प्रत्यक्ष, संअभि-मुख (खी f.), समीपवर्तिन्; *See* **Near**; 'to be p.' उप-स्था 1 P, संनिधा-pass., समीपे वृत् 1 A; 'you should be p.' त्वयोपस्थातव्यं, संनिहितेन भाव्यं; 'to be p. in one's thoughts' हृदये-चित्ते-वस् 1 P. -s. भवत् n.; समतीतं च भवच्च भावि च (R. viii. 78) 'the past, p. and future.' 2 वर्तमान-प्रस्तुत-कालः, तत्कालः, तत्क्षणः, आपातः. 3 (In grammar) लट्. 4 उपायनं, उपहारः, उपदा, प्र-,दानं, वितरणं, पारितोषिकं, उपग्राह्यं, प्राभृतं, प्रदेशनं, प्रीतिदानं; 'p. of money' दक्षिणा; *See* **Gift**. -able,

a. उपहार्य, देय, दर्शनीय, प्रवेश्य. 2 पांक्तेय, पांक्तय, सभ्य. **-ation,** *s*. उपहरणं, अर्पणं, प्रतिपादनं, दानं; 'p. of an oblation' बलिदानं, निर्वपणं. **-ly,** *adv*. अधुना, संप्रति, सांप्रतं. 2 सपदि, अनंतरं, द्राक्, तत्क्षणं-णे, तत्काले, सद्यः, अचिरात्, शीघ्रं, आशु, झटिति. **-Presence,** *s*. संनिधिः, समुपस्थिति *f*., उपस्थानं, सांनिध्यं, सन्निधानं, प्रत्यक्षता, समक्षता, आभिमुख्यं; 'in the p. of' समक्षं, प्रत्यक्षं, संमुखं, साक्षात्, in comp. or with gen.; in the p. of fire' अग्निं साक्ष्ये आधाय (R. vii. 20); 'into the p. of' सकाशं-शे, समीपं-पे, अंतिकं, in comp. or with gen. 2 आकारः, आकृति *f*., रूपं, शरीरसंस्था. 3 (Of mind) प्रत्युत्पन्नमति *f*., प्रतिभा, प्रतिभानं, प्रतिभानवत्त्वं, समाहितत्वं, अव्यग्रता, असंभ्रमः, निराकुलत्वं; 'p.-chamber' दर्शनशाला, आस्थान-नी.

Presentiment, *s*. पूर्वज्ञानं-बोधः-कल्पना; 'my mind has a p. of evil' मम मनः किमप्यशुभमाशंकते.

Preserve, *v. t*. रक्ष् 1 P, त्रै 1 A, पा c. (पालयति), उद्-धृ 1 P, 10, गुप् 1 P, पा 2 P, वृ c., अव् 1 P, परि-आप् desid. (ईप्सति), (इमां परीप्सुः दुर्जातेः M. 5). 2 सं-,भृ 3 U, पुष् c., संवृध् c., पा c. (पालयति). 3 सं-धा 3 U, उपस्कृ 8 U. **-s.** संधितं, उपस्करः, मिष्ट or संधित-फल or द्रव्यं. 2 वि(वी)तंसः, विहगस्थानं. **-ation,** *s*. सं-, रक्षा-क्षणं, त्राणं, स्थितिपालनं, गोपनं, तारणं. **-ative,** *s*. रक्षा, रक्षणं, रक्षण-त्राण-साधनं, -त्राणं in comp. **-a**. रक्षक, पालक, तारक.

Preside, *v. i*. (Over) अधि-ष्ठा 1 P, अध्यास् 2 A, (with acc.); अधीश् 2 A, प्र-भू 1 P (with gen.); अवेक्ष् 1 A, अध्यक्षः-अधिपतिः-भू, अभिमन् 4 A; अग्न्याद्यभिमानिनीभिर्देवताभिः (S. B. 725) 'p.ing over fire &c.' **-ency,** *s*. अध्यक्षता, अधिष्ठानं, अधिकारः. 2 आधिपत्यं, अधिष्ठातृत्वं, अध्यक्षपदं, अधीशत्वं, better by (*v*.); 'during his p.' तस्मिन्नधितिष्ठति. 3 मंडलं, भोगः, देशविभागः. **-ing,** *a*. अध्यक्ष, अधिष्ठातृ, अभिमानिन्, अधि pr.; 'the p. deity' अधिदेवता, अधिष्ठात्री देवता; 'the soul p. over the body' शरीराभिमानी आत्मा. **-President,** *s*. अध्यक्षः, अधिष्ठातृ *m*. अधीशः, अधि-,पतिः, अध्यासीनः, अधिकारिन्, *m*. प्रभुः, नायकः. **-ship,** *s*. आधिपत्यं, अध्यक्षता; *See* **Presidency.**

Press, *v. t*. पीड् 10, निः-आ-°, निष्पिष् 1 P, निर्दह् 1 P, निर्दुह् 2 U; (together) संपीड्, संहन् 2 P, संहृ, संकुच् 1 P, संपिंड् 10, संघट्ट् c. 2 **Clasp,** q. v; 'p. ing him to the bosom' तं वक्षसा परिरभ्य; भुजाभ्यां आपीड्य 'p. ing in the arms' &c. 3 प्रेर् c., प्रचुद् 10, प्रणुद् 6 P or c., आकृष् 1 P, आकृ c. 4 निर्बंध् 9 P, अनु-अनुनिर्बंध्, साग्रहं-निर्बंधेन-प्रच्छ् 6 P or याच् 1 A or अर्थ् 10 A, पुनः पुनः प्रच्छ्, *See* **Importune.** 5 बलेन प्रवृत् c. or नियुज् 7 A, 10 or व्यापृ c. 6 बाध् 1 A, पीड्, क्लिश् 9 P, उद्विज् c., सं-परि-तप् c., व्यथ् c (व्यथयति). 7 मुहुर्मुहुः-पुनः पुनः-उपदिश् 6 P or कथ् 10 or अनुशास् 2 P. **-v. i.** समापत् 1 P, आ-अभि-क्रम् 1 U, 4 P, अभिद्रु 1 P; (against,) संघट्ट् 1A, प्रतिहन् 2 P, अभ्याहन्; संघट्टयन्नंगदमंगदेन (R. vi. 73); 'making his Angada ornament p. against Indra's.' 2 सवेगं प्रगम् or प्रसृ 1 P, सरभसं उपसृप् 1 P or संगम् 1 A; 'p.-ing close to the rock' शिलायामात्मानं निबिडं-निरंतरं-संसंजयन्. 3 प्र-, बाध् 1 A; 'my time p. es' कालातिपातो मया नैव कर्तुं शक्यते, 'p. through' अतीत्य-अतिक्रम्य-गम्, उल्लंघ् 1 A, 10, निस्तॄ 1 P. **-s.** पीडनं, निष्कर्षः. 2 मुद्रण-मुद्रायंत्रं. 3 पीडन-पेषण-यंत्रं. 4 जनसंकुलं-संमर्दः. लोकनिवहः. 5 निर्बंधः, पीडा, अतिभारः. **-er,** *s*. पीडकः, बाधकः. **-ing,** *a*. अतिनिर्बंधक, बाधक, अत्यवश्यक, अविलंब्य, अव्याक्षेप्य, विलंबाक्षम, अनतिपात्य; 'p. business of state' आशुसंपादनीयं-विलंबाक्षमं-राजकार्यं. **-ingly,** *adv*. निर्बंधेन, सनिर्बंधं, साग्रहं. **-ure,** *s*. पीडनं. 2 बलं, शक्ति *f*., प्रभावः, वेगः, प्रवर्तनं, प्रेरणा, प्रणोदः, प्रोत्साहः. 3 भारः, पीडा, बाधा, क्लेशः; 'p. of business' कार्यभारः; having much p. of work' कार्यसमाकुल.

Prestige, *s*. दीर्घकाल प्रतिष्ठा, चिरप्रतिष्ठितं गौरवं. 2 माया, इंद्रजालं.

Presto, *adv*. *See* **Quickly.**

Presume, *v. t*. (अविचार्य-अविनिश्चित्य) तर्क् 10, सं-भू c., अनु-मा 3 A, 2 P. 2 धृष् 5 P, धार्ष्ट्येन आक्रम् 1 U, 4 P, उत्सह् 1 A, प्र-भू 1 P; प्रगल्भ् 1 A, दृप् 4 P, साहसं कृ 8 U; कः पतिदेवतामन्यः परिमार्ष्टुमुत्सहेत (S. 6) 'p. to lay hands on &c.'; तद्दोषनिरूपण रूपं साहसं मा कुरु 'do not p. to find fault with him'. **-Presumption,** *s*. तर्कः, कल्पना, भावना, अनुमानं, ग्रहणं. 2 साहसं, धार्ष्ट्यं, प्रागल्भ्यं. 3 अवलेपः, दर्पः, अभिमानः, अहंकारः, गर्वः. 4 संभाव्यता, संभवः. **-Presumptive,** *a*. आनुमानिक (की *f*.), अनुमानसिद्ध, संभावित; 'p. proof' अनुमाननिर्णयः. **-Presumptuous,** *a*. साहसिक (की *f*.), धृष्ट, धृष्णु, प्रगल्भ. 2 अवलिप्त, अत्यभिमानिन्; 'a p. statement' साहसोक्ति *f*., साहसं. **-ly,**

adv. साहसेन, धृष्टवत्, प्रगल्भं, सावलेपं, सगर्वं. **-ness**, *s*. धृष्टता, प्रागल्भ्यं; प्रतिभा, प्रतिभानं.

Presuppose, *v. t*. पूर्वं क्लृप् c. or बुध् c. **-ition**, *s*. पूर्वकल्पना-भावना.

Pretend, *v*. अप-व्यप-दिश् 6 P, छलं-कपटं-व्याजं-कृ 8 U ध्वजीकृ; gen. ex, by मिथ्या, कृतक, कपट, व्याज, छल in comp. or by धृ c., दृश् c.; 'p. ing to be asleep' सुप्तमिव आत्मानं संदर्श्य, व्याजसुप्त, सुप्तलक्षण, मिथ्यासुप्त; 'p. ing to be affected by poison' भावितविषवेगः; 'p. s not to hear' अश्रुतिमभिनयति; 'p. ing to be just' आर्यध्वजिन्-लिंगिन्; 'p. ed weeping' कपट-व्याज-रोदनं. **2** अभिमन् 4 A, मिथ्या मन्; 'he p. s to know everything' अहं सर्वज्ञोस्मीति तस्याभिमानः (अवलेपः). **3** मिथ्याहेतुं दृश् c. or वद् 1 P. **-ed**, *a*. छाद्मिक-कौटिक-(की *f*.), व्याज-कपट-छल-कूट-मिथ्या in comp.; 'p. ascetic' छद्मतापसः, तापसध्वजी-लिंगी; *See* **Hypocrite**; *See* (*v*.) also. **-edly**, *adv*. सकपटं, सव्याजं, छलेन, मिथ्या. **-ing**, *a*. **-er**, *s*. छाद्मिकः, कापटिकः, अभिमानी-ध्वजी-लिंगी-मन्यः-अभियोगी in comp.; 'p. in learning' पंडितंमन्यः, विद्याभिमानी; 'p. in religion' धर्मध्वजी, आर्यलिंगी, धार्मिकवेशधारी, कपटधर्मी; 'p. to the throne' राज्याभियोगी. **-Pretence**, *s*. व्याजः, अप-व्यप-देशः, छद्मन् *n*., उपधिः, कपटं, छलं, उपधा, कूटः-टं, कैतवं, मिषं, मिथ्याहेतुः, निमित्तं. **2** अभिमानः, अभियोगः. **-Pretension**, *s*. अभिमानः, अभियोगः, स्वस्वप्रतिपादनं; 'lay p. s to' *See* **Claim**. **2** महत्त्वाकांक्षा, यशोलिप्सा, लोभः; 'p. s to the throne' राज्यं मदीयमिति प्रतिपादनं, राज्याभियोगः.

Preterite, *a*. भूत, परोक्ष; 'p. tense' लङ्.

Preterition, *s*. अतिक्रमः-मणं, अत्ययः.

Pretermit, *v. t*. *See* **Omit**.

Preternatural, *a*. अद्भुत, विलक्षण, निसर्ग-प्रकृति-बाह्य. **-ly**, *adv*. अद्भुतं, वैलक्षण्येन.

Pretext, *See* **Pretence** under **Pretend**.

Pretty, *a*. सु in comp., चारु, शोभन, कमनीय, वाम, सुंदर; *See* **Beautiful, Lovely**. **-adv**. ईषत्, स्तोकं, अल्पं; आ, कल्प, देश्य, देशीय in comp.; 'p. warm' मंदोष्ण, कोष्ण, कवुष्ण; 'p. clear' सुव्यक्तकल्प-प्राय; 'p. ripe' आपक्व, पक्वप्राय. **2** (P. nearly) प्रायेण, प्रायशः, बहुशः. कल्प-भूयिष्ठ-प्राय in comp.; 'p. nearly finished' समाप्तभूयिष्ठ &c. **-ly**, *adv*. चारु, सुंदरं, चारु-सु in comp. **-ness**, *s*. चारुता, सौंदर्यं, लावण्यं.

Prevail, *v. i*. अभिभू 1 P, प्र-भू, पराभू, पराजि 1 A, आक्रम् 1 U, 4 P; अति-शी 2 A, अतिरिच् pass., प्रबल-क्षम-*a*. भू; *See* **Excel**. **2** (In) प्रचलित-प्रवृत्त-*a*. भू, प्रचल्-वृत् 1 P, प्रवृत् 1 A; 'darkness p. ed everywhere' सर्वं तमोवृतं आसीत्. **3** सिध् 4 P, सिध्यति 4 A; 'p. with, on, or upon' अनुनी 1 P, प्रवृत् c., प्रोत्सह् c.; *See* **Persuade**; 'p. against' मूर्छ् 1 P, (मारुतस्य रंहः शिलोच्चये न मूर्च्छति R. II. 34). **-ing,-Prevalent**, *a*. प्रचलित, साधारणी-बहुली-भूत, प्रसिद्ध, प्रचल, प्रवृत्त, साधारण (णी *f*.); 'universally p.' सर्वत्र प्रचलित, सर्वप्रवृत्त; 'long since p.' चिरप्रवृत्त. **2** प्रबल, प्रधान, अतिरिक्त, अधिकबल, प्रभविष्णु, सप्रभाव. **-ingly**, *adv*. प्राबल्येन, सप्रभावं. **-Prevalence**, *s*. प्रचारः, प्रवृत्ति *f*., प्रचलनं, प्रसिद्धि *f*., साधारण्यं. **2** प्राबल्यं, प्राधान्यं, आधिक्यं, अतिरेकः.

Prevaricate, *v. i*. सापह्नवं मिथ्योत्तरं ब्रू 3 U, अप-व्यप-दिश् 6 P, छलं कृ 8 U, अपलप् 1 P, अप-नि-ह्नु 2 A, वाक्छलं कृ; 'when he p. ed' यदा वाक्यभेदान् बहून् कथयत् (Mu. 2). **-ing**, *a*. अपलापिन्, निह्नवकारिन्, व्यपदेशिन्. **-ion**, *s*. वाक्छलं, अपलापः, अप-नि-ह्नवः, व्यप-अप-देशः, वक्रोक्ति *f*., छलवादः, उत्तराभासः.

Prevent, *v. t*. वृ c., नि-विनि-°, रुध् 7 U, प्रति-अव-नि°, प्रति-नि-षिध् 1 P, प्रतिकृ 8 U, बाध् 1 A, प्रतिबंध् 9 P, प्रतिष्टंभ् 9 P, प्रति-व्या-हन् 2 P, प्रत्या-ख्या 2 P, निवृत् c., अंतरायः भू- परिपंथीभू 1 P: 'do not p. me from fighting' युध्यमानं मां मा रुंद्धि, युध्यमानस्य मेंऽतरायो मा भूः. **-ion**, *s*. प्रतिरोधः, नि-, वारणं, प्रतिबंधः, प्रतिकारः, व्याघातः, प्रतिषेधः; 'p. is better than cure' प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं. **-ive**, *a*. हर (री *f*.), घ्न (घ्नी *f*.), in comp., निवारक, प्रतिबंधक, निरोधक. **-s**. वारणं, प्रतिबंधकं.

Previous, *a*. पूर्व, प्राग्भूत, भूत, गत, अतीत, पूर्ववृत्त-गत, प्राक् in comp. **-ly**, *adv*. पूर्वं, प्राक्, पुरस्तात्, पूर्व in comp.

Previse, *v. t*. अग्रेदृश् 1 P or निरूप् 10. **2** पूर्वं सूच् 10 or प्र-बुध् c. **-ion**, *s*. अग्रनिरूपणं-दृष्टि *f*.

Prey, *s*. आमिषं (fig. also); मांसं, भक्ष्य, अर्थः, खाद्यं, भोज्यं; 'fell a p. to enemies' द्विषामामिषतां ययौ (R. XII. 11). **-v. i**. भक्ष्यं आ-अप-हृ 1 P. **2** (Upon) भक्ष् 10; संतप् c., बाध् 1 A, क्रमशः नश् c.

Price, *s*. मूल्यं, अर्घः, पण्यं, अवक्रयः, वस्नं; 'high p.' महार्घः, बहुमूल्यं. **-v. t**. मूल्यं स्था c. (स्थापयति) or संकॢप् c. **-ed**, *a*. कृतमूल्य; 'high-p.' महार्घ-र्घ, बहुमूल्य.

दुर्मूल्य; 'low-p.' अल्पमूल्य. **-less,** *a.* अनर्घ-र्घ्य, अमूल्य.

Prick, *v. t.* व्यध् 4 P, भिद्-भिद् 7 P, तुद् 6 P, पीड् 10: व्यध् c. (व्यधयति), क्लिश् 9 P or c. 2 मेद् c., उत्तिज् c., प्रोत्सह् c., मथ् 6 P or c. 3 (Ears) उन्नम् c. (नमयति), उच्छ्रि 1 U, स्तब्धीकृ 8 U; 'with ears p.-ed' स्तब्धकर्ण. **-s., -ing,** *s.* प्रतोदः, तोत्रं,तोदनं; सूचि *f.*, शल्यं, कंटकः. 2 वेधः-धनं, तोदनं. 3 यातना, तीव्रव्यथा, आतंकः, शूलः-लं. **-ed,** *a.* विद्ध, भिन्न, शल्य-सूचि-विद्ध-भिन्न; 'p. at heart' भिन्न-विद्ध-मर्मन्. **-er,** *s.* वेधकः. 2 तोत्रं; *See* (*s.*).

Prickle, *s.* कंटकः, सूचि-ची *f.*, शल्यं, शूकं. **-y,** *a.* सकंटक, सशूक, बहुकंटक-शूक.

Pride, *s.* (Good) अभिमानः. 2 अहंकारः, गर्वः, उत्सेकः, अवलेपः, दर्पः, औद्धत्यं, मदः, मादः, आटोपः, अहंमानः, मानः, चित्तसमुन्नति *f.*, अवष्टंभः, चित्तोद्रेकः, स्मयः; (impudent) प्रागल्भ्यं, धृष्टता, प्रतिभा-भानं. 3 अलंकारः, अवतंसः, ललामं,अभिमानास्पदंभूमिः. **-v. t.** (Oneself upon) आत्मानं श्लाघ् 1 A or विकत्थ् 1 A, अभिमन् 4 A, or ex. by (*s.*); 'p.-ing himself on his learning' पंडितमानी, पंडितंमन्यः, विद्याभिमानी, जातज्ञानावलेपः; 'p. ing herself upon her beauty' रूपगर्विता. **-Proud,** *a.* (In a good sense) अभिमानिन्. 2 दृप्त, गर्वित, अवलिप्त, सगर्व, सदर्प, उत्सिक्त, उद्धत, उत्सेकिन्, अभिमानिन्, साटोप, साहंकार; अहंमानिन्, उत्-, मत्त, समुन्नद्ध; प्रगल्भ, धृष्ट, प्रतिभावत्, गर्वितचित्त, मदोद्धत, दर्पाध्मात, स्मयाकुल. 3 (Building &c.) उत्तुंग, प्रोच्छ्रित, विशाल, सप्रताप; 'p. of one's birth' कुलाभिमानिन्; रूपगर्वित, यौवनोन्मत्त, &c.; 'to be p.' दृप् 4 P गर्व 1 P, प्रगल्भ् 1 A. **-ly,** *adv.* सदर्पं, सगर्वं, सावलेपं, साटोपं, साहंकारं, उद्धतं.

Priest, *s.* (Family) पुरोहितः, पुरोधस् *m.* कुलाचार्यः. 2 (Sacrificial) ऋत्विज् *m.*, याजकः, अध्वर्युः,होतृ *m.* याज्ञिकः 3(Vedic) श्रोत्रियः, मंत्रविद् *m.*, ब्राह्मणः, द्विजः, विप्रः. 4 आचार्यः, गुरुः, उपाध्यायः, पुरोहितः, धर्माचार्यः, धर्माध्यक्षः. 5 (Of a deity) पुजकः, उपासकः, अर्चकः; 'p.-craft' उपाध्यायछलं-कैतवं; 'p.-ridden' पुरोहिताधीन. **-ess,** *s.* होत्री, याजिका. **-hood,** *s.* पौरोहित्यं, उपाध्यायपदं-वृत्ति *f.*, 2 पुरोहिताः,पुरोहित or याज्ञिक-गणः or वर्गः, पौरोहित्यं. **-ly,** *a.* याजकीय, पौरोहित्यसंबंधिन्, (*s.*) in comp.

Prig, *s.* दांभिकः, दंभिन् *m.*, रूपगर्वितः. **-gish,** *a.* दांभिक (की *f.*), आत्माभिमानिन्.

Prim, *a.* अतिविनीत, अतिसूक्ष्म.

Prime, *s.* आदिः, आरंभः, पूर्व-प्रथम-भागः. 2 उत्तमदशा, प्रौढता, उत्तमभागः-अंशः; 'in the p. of youth' प्रथमे वयसि; 'the p. of youth' प्रथमं वयः, नव-अक्षत-यौवनं, यौवनश्रीः; 'being in the p. of youth' अक्षत-नव-यौवन. **-a.** प्रथम, आद्य. 2 मुख्य, प्रधान, प्रमुख, अग्र्य; 'p. minister' मुख्यमंत्री, प्रधानामात्यः, महामंत्री. 3 उत्कृष्ट, श्रेष्ठ, परम, उत्तम, विशिष्ट; *See* **Principal. -ly,** *adv.* प्रथमं, श्रेष्ठं. **-ness,** *s.* उत्तमता, विशिष्टता. **-Primary,** *a.* प्रथम, आद्य, आदिम, पूर्व, मौल (ली *f.*), मूल-आदि in comp.; 'p. cause' आदिकारणं-बीजं, निदानं, मूलहेतुः; 'p. sense' मूलार्थः. 2 प्रधान, मुख्य, प्रमुख, अग्र्य; *See* **Prime. -ily,** *adv.* प्रथमं-मतः, अग्रे, पूर्वं, मुख्यशः, प्राधान्येन. **-iness,** *s.* प्रथमता, प्राधान्यं. **-Primate,** *s.* प्रधानोपाध्यायः. **-Primer,** *s.* प्रथम-आरंभ-पुस्तकं. **-Primeval,** *a.* आद्य, आदिम, प्राक्कालीन, पूर्वकालीन, प्राक्तन (नी *f.*), मौलिक-प्राथमिक- (की *f.*). **-Primitive,** *a.* प्राथमिक, प्रथम, आद्य; *See* **Primeval.** 2 मूल in comp., अव्युत्पन्न; *See* **Primary.** 3 प्राक्तनमार्गसेविन्. **-ly,** *adv.* आदौ, आरंभे, प्रथमं-मतः. 2 प्राक्तनव्यवहारानुसारेण.

Primogenial, *a.* प्रथम-आदि-जात, मूल in comp.

Primogenitor, *s.* प्रथम-कुल-पुरुषः. **-Primogeniture,** *s.* पूर्वजत्वं, ज्येष्ठत्वं, अग्रजत्वं, वयोज्येष्ठता.

Primordial, *a.* आद्य; बीजभूत, मौल (ली *f.*), *See* **Primeval.**

Prince, *s.* कुमारः, राजपुत्रः-सुतः, युवराजः. 2 नृपः, राजन् *m.*, पार्थिवः; *See* **King. 3** भर्तृदारकः, कुमारः, (in dramas). **-dom,** *s.* राज्यं, राष्ट्रं, विषयः. 2 यौवराज्यं. **-like, -ly,** *a.* राजयोग्य-सदृश (शी *f.*),राजार्ह,नृपोचित,नृपोपम, राजकीय, प्रतापवत्, ऐश्वर्यवत्, प्रताप-वैभव-शालिन्. 2 राजवंश्य, राजकुलज; 'p. birth' राजवंशप्रसूतिः; 'p. merits' राजोचिता गुणाः **-Princess,** *s.* कुमारी, राजपुत्री, नृपात्मजा, नृपसुता, भर्तृदारिका.

Principal, *s.* अध्यक्षः, अधि-,पतिः, नायकः, मुख्यः; *See* **Leader. 2** मूलं,मूलधनं, नीवि-वी *f.*, परिपणः. **-a.** मुख्य, परम, प्रधान-वर in comp., प्रमुख, अग्र, अग्र्य, प्रवर, श्रेष्ठ, विशिष्ट, उत्कृष्ट, उत्तम, अनुत्तम, वर्य, वरेण्य, परार्ध्य, अग्नि(ग्री)य, प्राग्रहर; नायक, अग्रणी, धुरीण, धुर्य, धुरीण, धूर्वह, धुरंधर; oft. ex. by व्याघ्र, पुंगव, ऋषभ, कुंजर, सिंह, शार्दूल, नाग, प्रकांड, in comp.; *See* **Excellent,** 'p. door' सिंहद्वारं; 'p. queen' अग्र-पट्ट-महिषी; 'p. minister' प्रधानामात्यः. **-ity,** *s.* राष्ट्रं, प्रदेशः, मंडलं,

साक्षं. -ly, adv. प्रधानतः, प्राधान्येन, मुख्यतः, विशेषतः, विशेषेण.

Principle, s. तत्त्वं, मूलतत्त्वं, बीजं, सारः. 2 कारणं, हेतुः, आदिबीजं-हेतुः, मूलं, अंशं, अवयवः, साधनं, मूलांश-द्रव्यं. 3 नियमः, विधिः, सूत्रं, उत्सर्गः, स्थितिf., व्यवस्था. 4 गुणः, भावः, धर्मः, स्वभावः. 5 क्रमः, रीतिf., मार्गः, मर्यादा, धारा, पद्धतिf. 6 आचारः, आश्रयः, उपदेशः, मूलं; (opp. of practice) आगमः, शास्त्रं; 'grounded in p. s' आगमिक, शास्त्रनिपुण, 'having good p.s' सुविचारसिद्ध, सुवृत्त; 'of bad p-s.'; संदिग्धवृत्त, असच्चरित.

Print, v. t. मुद्रयति (D.). अंक् 10, मुद्राभिः अंक्. -s. चिह्नं, अंकः, मुद्रा; 'foot-p. पदं, पदमुद्रा-चिह्नं. 2 मुद्रणयंत्रं. 3 मुद्रणं; 'in p.' मुद्रमाण. -ed, a. मुद्रित, मुद्रांकित, मुद्राक्षरांकित. -er, s. मुद्रकः; मुद्रणकृत् m. -ing, s. मुद्रणं, मुद्रांकनं, 'p.-house' मुद्रणयंत्रालयः, मुद्रणशाला; 'p.-press' मुद्रणयंत्रं.

Prior, a. प्रथम, भरीयस्, पूर्वतर, पूर्व, अग्र्य, आदिम, आद्य, पूर्व-आदि-प्राक् in comp.; 'p. existence' प्राग्भावः, पूर्व जन्म; 'p. and subsequent' पूर्वापर, परापर, परावर. -s. मठाध्यक्षः, मठाधिपतिः, विहारपालः. -ity, s. पूर्वता, प्रथमता. (Of rank) अग्रपदं-भागः; श्रेष्ठपदं, प्राधान्यं. -y, s. मठः-विहारः, आश्रमः.

Prism, s. ककचायतं. -**Prismatic**, a. ककचायत.

Prison, s. कारा, बंदिशाला-गृहं, बंधनालयः, कारागृहं, कारः-रक्षः, गुप्तिस्थानं; 'escaped from the p.' बंधनं भित्त्वा पलायांचक्रे; 'keep in p.' बंधने निरुध् 7 U. -er, s. बांदि-दी f., कारागुप्तः, बद्धः, कारागारस्थः. 2 (Of war) युद्धगृहीतः.

Pristine, a. प्राक्तन (नी f.), पुराण, पूर्व, पूर्वकालिक (की f.), प्राचीन, प्राक्कालीन.

Private, a. विजन, विविक्त, निर्जन, एकांत, निभृत, निःशलाक. 2 स्व, आत्मीय, असाधारण (णी f.), असामान्य, विविक्त, स्व-आत्म in comp. 3 गुप्त, गूढ, रहस्य, प्र-,छन्न, अप्रकट, अव्यक्त, रहस्-मिथः-अंतः-in comp. 4 अनधिकारिन् अनधिकारिक (की f.); 'p. profit' आत्महितं, स्वलाभः; 'p. road' गुप्त-प्रच्छन्न-मार्गः; 'p. door' अंतर्द्वारं, गुह्यद्वारं, पक्षद्वारं; 'p. apartments' अंतःपुरं, अवरोधगृहं, अंतर्गृहं; 'now is the time to be p.' रहस्यमनुगम्यतां (Bh. II 97); 'p. talk' रहःसंकथा, मिथोजल्पः; 'p. parts' गुह्यं, उपस्थः; 'p. room' अंतःशाला-कोष्ठः, अपरोधकं. -s. सैनिकः. -ly, 'in p.' adv. रहः, रहसि, मिथः, रहस्ये, निभृतं, विविक्ते, एकांते, विजने, उपांशु, गूढं, प्रच्छन्नं, छन्नं, अप्रकाशं, अप्रकटं. -ness, -**Privacy**, s. रहस् n., विविक्तं, विजनं, रहोभावः, विविक्त-एकांत-भावः, रहस्यं, गुप्तता, छन्नता, अप्रकाश्यं. 2 रहःस्थानं-स्थलं, विविक्त-निर्जन-स्थानं, निर्जनदेशः.

Privation, s. अभावः, विरहः, राहित्यं, हानिf., क्षयः, लोपः, नाशः. 2 कष्टं, दुःखं, आपद्-विपद्f. 3 आहारविरहः, आहाराभावः, सुख-साधनलोपः, अन्नपानहानिः. -**Privative**, a. हानि-क्षय-लोप-कार (री f.). 2 अभावात्मक, अभावरूप, अभावबोधक. -s. अभाव-शब्दः, नञ्पदं. -ly, adv. अभावबोधेन.

Privilege s. विशेषाधिकारः, असामान्याधिकारः, स्वाधिकारः, अधिकारः, स्वत्वं. -v. t. विशेषाधिकारं दा 3 U. -ed, a. अधिकार-विशिष्ट, साधिकार, विशेषाधिकारयुक्त.

Privy, a. गूढ, प्रच्छन्न, विविक्त, रहः in comp.; See **Private**. 2 (To) संसर्गिन्, सहाय, सहकारिन्, सहज्ञानिन्, सहवेदिन्; 'p. council' गूढसभा; 'p. councillor' गूढसभासद्. -s. शौचस्थानं-कूपः, अवस्कर-प्रक्षालनस्थानं. -ly, adv. रहसि, गूढं; See **Privately**. -**Privity**, s. सहकारिता, सहायता, संसर्गः, सहज्ञानं. 2 गुह्य or गुह्य-स्थानं or इंद्रियं, अपांगं.

Prize, s. पारितोषिकं, उपायनं, प्रतिफलं. 2 रत्नं, बहुमूल्यं वस्तु, महार्घद्रव्यं. 3 युद्धजितं धनं-द्रव्यं. 4 जय or सिद्धि-फलं or लाभः. 5 स्पर्धा-पण-जेयं, पणः; 'p.-fighter' मल्लः; 'p.- fighting' मल्लयुद्धं, स्पर्धायुद्धं. -v. t. बहु मन् 4 A, अपेक्ष् या c. (पालयति), संमन् c. 2 मूल्यं-अर्घं-निरूप् 10 or निर्णी 1 P. -ed, a. बहुमत, अभीप्सित, इष्ट.

Pro, Prefix, प्र, अग्रे; 'p. s and cons:' विधिनिषेधपक्षौ.

Probable. a. संभाव्य, सत्यसंकाश; gen. ex. by सं-भू 1 P, उप-पद् 4 A, युज् pass. or by (adv.); 'It is p.' एतत् उपपद्यते, संभवति, युज्यते, स्यादाम एवं. -**Probably**, adv. प्रायेण, प्रायः, प्रायशः, किल, नाम,: स्यात्; by pot. pass. part. of भू; एतेन मम मित्रेणभवितव्यं 'he is p. my dear friend.' -**Probability**, s. संभवः, संभाव्यता, अनुमानं, better by (adv.).

probate, s. मृतलेखप्रमाण.

Probation, s. परीक्षा-क्षणं. -ary, a. परीक्ष्यमाण. -er, s. परीक्ष्यमाणः; अंतेवासिन् m., नवशिष्यः, प्राथमकल्पिकः.

Probe, s. शलाका, एषणी. -v. t. शलाकया परीक्ष् 1 A. 2 निपुणं-सूक्ष्मं-परीक्ष् or आलोच् 10. -ator, s. परीक्षकः. -ing, s. व्रणपरीक्षणं.

Probity, s. See **Honesty**.

Problem, *s.* प्रश्नः, विकल्प or विचार-प्रश्न or विषयः. 2 कृत्यं, उपपाद्यं. 3 (Question) उद्देशकः (in Math.); 'its solution' न्यासः (Lit.). **-atical**, *a.* संदिग्ध, अनिश्चित, वैकल्पिक (की *f.*).

Proboscis, *s.* प्रोथः, करः, शुंडा, हस्तः.

Proceed, *v. i.* प्रचल् 1 P, प्र-या 2 P, प्रसं-चर् 1 P, अग्रे गम्, प्र-स्था 1 A. 2 प्रवृत् 1 A, न विरम् 1 P; 'the play still p. s' क्रीडा अद्यापि प्रवर्तते एव. 3 पुनः कर्तुं प्रवृत्. 4 प्रवृत्, आरभ् 1 A, प्र-उप-क्रम् 1 A; (with) प्रस्तु 2 U or c., प्रवृत् c., (प्रारब्धं) सं-पद् c., निष्पद् c., निर्वह् c.; 'p. with your tale' ततस्ततः, ततः, परं कथय; 'p with the matter at issue' प्रस्तूयतां विवादवस्तु (M. 2); 'you may p. with your dinner preparations in honor of the worthy Brāhmaṇas' प्रवर्त्यतां भगवतो ब्राह्मणानुद्दिश्य पाकः (Mu. I). 5 प्र-उद्-सं-भू 1 P, प्रवृत्, उत्पद् 4 A, प्र-,जन् 4 A, उद्-इ 2 P, निःसृ, निर्गम्; oft. ex. by कारणं, मूलं, निमित्तं, हेतुः; 'from what cause does thy disorder p.' किंनिमित्तं ते संतापः (S. 3). 6 (Against) अभियुज् 7 A, 10, राजकुले निविद् c. **-ing**, *a.* उत्पन्न, जात, प्रभव, उद्भव, उत्थित, मूल, कारण, निमित्त, हेतु in comp. *See* (*v.*). **-s.**, **-Procedure**, *s.* कार्यं, व्यवहारः, व्यापारः, चरितं, चेष्टितं, आचारः, वृत्तं, कृति *f.*, विधानं, अनुष्ठानं. 2 रीति *f.*, क्रमः, संप्रदायः, मार्गः, पर्यायः; 'legal p.' व्यवहारविधिः, व्यवहारक्रमः. **-Proceeds**, *s.* उत्पन्नं, उद्भवः, लाभः, फलं. **-Process**, *s.* प्रसरः, प्रगमः, प्रवृत्तिः, यानं. 2 क्रमः, रीतिः, मार्गः, पर्यायः, विधिः, गतिः, परिपाटि-टी *f.*, सरणि-णी *f.*, पद्धति *f.* 3 व्यवहारः, कार्यं; 'in p. of time' कालक्रमेण, दिनेषु गच्छत्सु, गच्छता कालेन. **-Procession**, *s.* यात्रा, जन or लोक-यात्रा or श्रेणी. 2 प्रगमनं, प्रस्थानं, प्रचलनं, प्रवृत्तिः. **-al**, *a.* यात्राकर्म.

Proclaim, *v. t.* घुष् 10, उद्-वि°-, प्र-ख्या c. (ख्यापयति), प्रकाश् c., प्रकटयति (D.), प्रकटीकृ, कृत् 10, उच्चर् c. 2 **Outlaw**, q. v. **-er**, *s.* घोषकः, प्रख्यापकः. **-Proclamation**, *s.* घोषः-षणं-णा, ख्यापनं, प्रकाशनं, उत्कीर्तनं; 'written p.' घोषणपत्रं, राजाज्ञापत्रं.

Proclivity, *s.* प्रावण्यं, प्रवृत्ति *f.*, शीलता in comp. **-Proclivious**, *a.* प्रवण, शील in comp.

Procrastinate, *v.* विलंब् 1 A, व्याक्षिप् 6 P, कालं क्षिप् or ह 1 P, चिर(रा)यति (D.), मंद्रायते (D.). **-ion**, *s.* विलंबः, दीर्घसूत्रता, व्याक्षेपः, कालयापनं-हरणं-क्षेपः. **-or**, *s.* दीर्घ-सूत्रः-त्रिन् *m.* चिरक्रियः.

Procreate, *v. t.* प्र-सू 2, 4 A, उत्पद् c., जन् c. (जनयति). **-ion**, *s.* प्रसवः, प्रसूति *f.*, जननं, उत्पत्ति *f.*, प्रजोत्पादनं. **-ive**, *a.* उत्पादक, साधक, जनयितृ. **-or**, *s.* जनकः, उत्पादयितृ *m.*

Proctor, *s.* प्रतिहस्तः, प्रतिनिधिः

Procumbent, *a.*, शयान, पतित.

Procure, *v. t.* आ-नी 1 P, सं-पद् c., घट् c. (घटयति). 2 लभ् 1 A, आप् 5 P, अधि-गम् 1 P, विद् 6 U, आ-समा-सद् c.; *See* **Get.** **-er**, *s.* प्रापकः, संपादकः. 3 विटः, नर्मसचिवः, संचारकः, कुंभदासिन् *m.* **-ess**, *s.* कुट्ट(ट्टि)नी, शंभली, दूती-तिका, संचारिका, कु-,रतताली.

Prodigal, *a.* मुक्तहस्त, अति-अमित-बहु-व्ययिन्, उत्सर्गिन्, अतिव्ययशील-पर, अतित्यागिन्. **-s.** मुक्तहस्तः, व्ययपरः. **-ity**, *s.* अतिव्ययः, अपव्ययः, बहु-अमित-व्ययः, अतित्यागः, अत्युत्सर्गः, अर्थोत्सर्गः, मुक्तहस्तत्वं. **-ly**, *adv.* महाव्ययेन, मुक्तहस्तेन, अत्युत्सर्गेण.

Prodigy, *s.* अद्भुतं, अद्भुत or अपूर्व-विषयः or वस्तु, उत्पातः, महाश्चर्यं, अनन्यसाधारणं वस्तु. 2 (Of persons) अद्भुतशक्ति, अद्भुतबुद्धिसंपन्न. **-ious**, *a.* महाप्रमाण, अतिमहत्-बृहत्, विकट-राक्षस-शरीर, अद्भुताकार; *See* **Giant.** 2 अद्भुत, अपूर्व, विलक्षण, विचित्र, आश्चर्य **-iously**, *adv.* अद्भुतं, साश्चर्यं. **-iousness**, *s.* अद्भुतता, अतिमहत्त्वं.

Produce, *v. t.* निर्मा 3 A, 2 P, सृज् 6 P, उत्पद् c., जन् c. (जनयति), उत्-सं-भू c., साध् 5 P or c., कृ 8 U, वि-धा 3 U, क्लृप् c., घट् c., (घटयति), वि-,रच् 10. 2 प्र-,सू 2, 4 A, उत्पद् c., सं-प्र-जन् c. 3 प्र-,दृश् c., आ-उपा-नी 1 P, प्रसृ c., पुरस्कृ, पुरोनि-धा, अग्रे स्था c. (स्थापयति) or निविश् c., आविष्कृ, प्रकटीकृ, निष्कृष् 1 P. 4 प्र-,धा 3 U. 5 वृध् c. **-s.** फलं, उत्पन्नं, लाभः, उत्पत्ति *f.*, प्रसवः. **-ed**, *a.* उत्पन्न, उत्पादित, निर्मित, घटित, सृष्ट, जनित, जात, उद्भूत; 'to be p.' जन् 4 A, उत्पद् 4 A, उत्था 1 P, सं-उद्-भू 1 P; *See* **Arise**; gen. ex. by ज, जात, जन्य, प्रभव, उद्भव, हेतु, प्रसूत, प्रसूत in comp.; 'p. from water' अंभोज, जलोद्भव, &c.; 'p. from flowers' कुसुमभव &c. **-er,-ing**, *s.*, *a.* उत्पादक, प्रसवित्, प्रद, द, दायिन्, आवह, कारिन्, कर (री *f.*), in comp. **-Product**, *s.* फलं, उत्पन्नं, लाभः. 2 परिणामः, फलं, उत्तरफलं. 3 गुणनफलं, घातः, घातः, फलं, गुणाकारः. **-ion**, *s.* उत्पादनं, निर्माणं, सृष्टि *f.*, करणं, विधानं, निष्पादनं. 2 जननं, उत्पत्तिः, प्रभवः, उद्भवः, संभवः, जन्मन् *n.* 3 निर्मितवस्तु, शिल्पनिर्माणं. **-ive**, *a.* उत्पादक-प्रसविन्, सफल, अवंध्य. 2 उत्पादक, दायिन्,

द, प्रद, कारिन्, आवह in comp.; 'p. of gain' लाभप्रद, लाभावह. 3 लाभ or फल-प्रद [or वृथ.

Proem, *s*. *See* **Preface**.

Profane, *v. t*. अपवित्रीकृ 8 U, दुष् c. (दूषयति). 2 लंघ् 1 A, 10, अतिक्रम् 1 U, 4 P, अतिचर् 1 P. 3 **Contemn**, q. v. —*a*. अपवित्र, अपुण्य, अमेध्य, अशुद्ध, not Holy q. v. 2 अधार्मिक (की *f*.), धर्म-ईश्वर-द्वेषिन्, धर्म-ईश्वर-निंदाकृत्. 3 असंस्कृत, अप्रतिष्ठित, संस्कारहीन. 4 लौकिक-सांसारिक-पार्थिवक- (की *f*.). **-ation**, *s*. दूषणं, अपवित्रीकरणं, अतिक्रमः-मणं. **-ly**, *adv*. धर्मनिंदापूर्वं, अधार्मिकवत्. **-ness**, *s*. धर्म or ईश्वर-निंदा- or द्वेषः, धर्म or ईश्वर-अवज्ञा or अतिक्रमः.

Profess, *v. t*. प्रति-ज्ञा A, प्रकाश् c., प्रतिज्ञापूर्वं कथ् 10 or वद् 1 P, स्वी-अंगी-कृ 8 U, उ(ऊ)रीकृ, अभ्युपगम् 1 P. 2 छल-छलं-कृ, दृश् c., धृ c.; *See* **Pretend**; oft. by नाम; तव कन्या नाम भवेयं (D. K. II. 5) 'I shall p. myself to be your daughter'. 3 उपास् 1 A, सेव् 1 A. **-ed**, *a*. स्वीकृत, अंगीकृत, प्रकाशित, प्रकटित, स्वकोक्षित, प्रकाश. **-edly**, *adv*. प्रतिज्ञापूर्वं, प्रकाशमेव, सप्रतिज्ञं. **-ion**, *s*. प्रतिज्ञा, उक्ति *f*., वचनं, अंगी-स्वी-कारः, प्रकाशवादः-वचनं, ख्यापनं. 2 **Pretension**, q. v.; 'p. s of love' कृत्रिमप्रीतिः, अलीकः रागाविर्भावः. 3 वृत्ति *f*., आ-उप-जीविका, आजीवः, व्यवसायः, व्यापारः; 'military p' शस्त्राजीवः, क्षत्रवृत्तिः. **-ional**, *a*. वृत्तिमत्, व्यवसायिन्, (*s*.) in comp. **-or**, *s*. अध्यापकः, गुरुः. 2 ख्यापकः, प्रकाशकः, प्रतिज्ञातृ *m*., स्वीकर्तृ *m*. **-orship**, *s*. अध्यापकपदं-पदवी.

Proffer, *v*. *See* **Offer**.

Proficient, *a*. प्रवीण, कुशल, निपुण, अभिज्ञ, विचक्षण, पारंगत, अभ्यंतर, निष्णात, व्युत्पन्न, लब्धप्रतिष्ठ, पटु. **-Proficience,-cy**, *s*. प्रावीण्यं, वैचक्षण्यं, प्रतिष्ठा, कौशलं, पाटवं; 'has attained p. in all sciences' सर्वशास्त्रेषु परां प्रतिष्ठां गतः, परं कौशलमवाप, सकलशास्त्रपारंगतः.

Profile, *s*. पार्श्वरूपं, अर्धमुखवर्णनं.

Profit, *s*. लाभः, हितं, उपकारः, अर्थः, कल्याणं. 2 फलं, लाभः, आयः, उदयः, वृद्धि *f*., कलांतरं, लब्धं; 'p. and loss' लाभालाभौ; 'capital with p. thereon' मूलकलांतरे. —*v. t*. हितमावह् 1 P, उपकृ 8 U, हिताय भू 1 P. —*v. i*. (Oneself) फलं-लाभं-आप् 5 P or विद् 6 U. 2 वृध् 1 A, उन्नतिं-उत्कर्षं-या 2 P, प्र-उप-चि pass.; *See* **Improve**. **-able**, *a*. लाभ-अर्थ-कर (री *f*.), लाभमद्, लाभ-फल-द, फल-लाभ-आवह. 2 हित, हितकर, हितावह, उपयुक्त, उपकारिन्, सोपकार. **-ableness**, *s*. साफल्यं, फलवत्ता, उपयुक्तता. **-ably**, *adv*.

सफलं, सफलं, सहितं, प्रयुक्त्या. **-less**, *a*. निष्फल, अफल, अहित, व्यर्थ, निरर्थक.

Profligate, *a*. दुर्विनीत, दुश्चरित, दुराचार, पाप-निरत-अभिनिविष्ट, व्यसनिन्, दुर्वृत्त, भ्रष्टचरित्र, भोग-विषय-आसक्त. —*s*. व्यसनिन् *m*. लंपटः, विषयिन् *m*. भोगासक्तः. **-ly**, *adv*. सव्यसनं, दुर्वृत्ततया. **Profligacy**, *s*. व्यसनिता, भ्रष्टचरितं, दुराचारः, शठता, भोगासक्ति *f*., दुर्वृत्तता.

Profound, *a*. प्र-,गाढ, अतिग(गं)भीर, घन, अगाध. 2 परम, गाढ, घन, अत्यंत, सु-अति- pr.; 'p. respect' परमादरः, आदरातिशयः. 3 गहन, नि-,गूढ, गूढार्थ, दुर्बोध, दुर्ज्ञेय, परमगहन. 4 (Of persons) निष्णात, पारंगत, परम, व्युत्पन्न, अभिनिविष्ट, सूक्ष्मदृश्. **-ly**, *adv*. गंभीरं, गाढं, अत्यंतं, भृशं, सु-अति pr. **-ness,-Profundity**, *s*. गांभीर्यं, अगाधता. 2 घनता, गाढता. 3 गहनता, गूढता. 4 अभिनिवेशः.

Profuse, *a*. प्रचुर, प्रभूत, अपरिमित, विपुल, बहु, अत्यधिक, अतिरिक्त, समृद्ध, उद्रिक्त, अतिशय-सु-अति in comp. 2 मुक्तहस्त, अतिव्ययिन्, व्ययपर, *See* **Prodigal**; 'he is a p. writer' बाहुपल्लवप्रियः, प्रचुरवाक्यानि लेखे प्रयोजयति. **-ly**, *adv*. प्रचुरं, भृशं, भूरि, बाहुल्येन, अत्यंतं, सु-अति pr.; अतिशयेन, अपरिमितं **-ness,-Profusion**, *s*. अतिव्ययः, अमितव्ययः, अत्युत्सर्गः. 2 समृद्धि, प्राचुर्यं, उद्रेकः, अतिरेकः, उपचयः, बाहुल्यं.

Pr[illegible] भोजनं, अन्नं, भैक्ष्यं.

Prog[illegible]r, *s*. पितृ *m*. प्रजापतिः, पूर्वजः, पूर्व[illegible]पुरुषः, जन्मदः, जनयितृ *m*. *See* **Ancestor**.

Progeny, *s*. संतानः, अपत्यं, संतति *f*., प्रजा.

Prognostic, *s*. निमित्तं, अजन्यं, शकुनः-नं, लक्षणं; *See* **Omen**. —*a*. प्र-उद्-बोधक, अग्रसूचक. **-ate**, *v. t*. पूर्व-अग्रे-सूच् 10 or दृश् c.; *See* **Forebode**. **-ation**, *s*. पूर्वसूचनं-ना. **-ator**, *s*. पूर्वलक्षणज्ञः, अग्रसूचकः.

Programme, *s*. सूचिपत्रं; कार्यक्रमः-परिपाटी.

Progress, *s*. प्र-,वृद्धि *f*., उत्कर्षः, क्रमशः वृद्धिः, उत्कर्षक्रमः. 2 प्राप्ति *f*., आगमः; 'p. in learning' विद्यागमः, विद्याभिनिवेशः. 3 प्र-गमनं, प्रयाणं, यानं, यात्रा, प्रस्थानं, प्रसरः, क्रमः-मणं, अयनं; *See* **March**; 'difficult p.' संक्रमः, दुर्गसंचारः. —*v. i*. उत्कृष् pass., वृद्धिं-उन्नतिं-या 2 P, प्र-वृध् 1 A, प्र-उप-चि pass.; *See* **Improve**. 2 प्रगम्-चल्-चर् 1 P, प्रया 2 P, प्रस्था 1 A; *See* **Advance**. **-ion**, *s*. श्रेढी, श्रेढीव्यवहारः; 'first term' मुखं, वदनं, आदिः; 'common difference' चयः; 'geometric mean' वर्गो गुणः; 'sum' श्रेढीफलं; 'number of terms' गच्छः. **-ive**, *a*. आनुक्रमिक (की *f*.),

क्रमिक, अधिकाधिक, उत्तरोत्तर, क्रमशः वर्धमान. -ively, *adv.* क्रमशः, अनुक्रमेण, उत्तरोत्तरं, अधिकाधिकं.

Prohibit, *v. t.* नि-प्रति-सिध् 1 P, प्रत्यादिश् 6 P, निवृ c., प्रत्या-ख्या 2 P, नि-अव-रुध् 7 U. -ion, *s.* नि-प्र ति-षेधः, प्रत्यादेशः, निरोधः, निवारणं, बाधा. -or, *s.* निवारकः, निषेधकः. -ive, -ory, *a.* निषेधक, निवारक, नि-प्रति-षेधिन्, निषेधार्थक, निषेधवाचिन्.

Project, *s.* उपायः, प्र-,युक्ति *f.*, कल्पना, प्रयोगः, संकल्पः, प्रबंधः. 2 अभिप्रायः, आशयः, उद्देशः. -*v. i.* प्रलंब् 1 A, बहिर्लंब्, उपरि लंब्, बहिः स्था 1 P or भू 1 P or वृत् 1 A. -*v. t.* प्र-,क्षिप् 6 P, प्रास् 4 U, निपत् c., प्रमुच् 6 P; *See* **Throw.** 2 (मनसा) कल्प् c., निरूप् 10, चिंत् 10, युज् 10, आलोच् 10, अनुसं-धा 3 U. -ile, *a.* प्रक्षेपणीय, दूरवेधिन्. -*s.* अस्त्रं, *See* **Missile.** -ing, *a.* प्र-,लंब, उन्नत, उदग्र, उत्तुंग, बहिर्वर्तिन्; oft. by उत्सेध, उत्सेधिन्; 'with a p. nose' प्रलंबनास, घोणोन्नत, उन्नस; 'having p. teeth' उदग्रदत्, करालदंष्ट्र; 'having p. breasts' स्तनाभोगवती, उन्नतस्तनी; 'shattered by falling over (her) p. breasts' पयोधरोत्सेधनिपातचूर्णिताः (K. v. 24). -ion, *s.* प्रलंबता, उदग्रता. 2 आभोगः, उत्सेधः, निर्यूहः, वृत्तकः. 3 छेद्यकं. -or, *s.* चिंतकः, योजकः.

Prolapse, Prolapsus, *s.* भ्रंशः. -*v. i.* भ्रंश् 1 A, 4 P.

Prolated, *a.* प्लुत (vowel), दीर्घोच्चारित.

Prolegomenon, *s.* प्रस्तावना, उपोद्घातः.

Prolepsis, *s.* पूर्वग्रहणं, पूर्वादानं.

Prolific, *a.* अवंध्य, बहुप्रज-प्रसव-अपत्य, प्रसवशालिन्, सुतिन्, बहुसंतान. 2 बहुफलप्रद, बहुफल; *See* **Productive.** -ally, *adv.* प्राचुर्येण, विपुलं.

Prolix, *a.* सु-अति-विस्तर, प्रपंचित, सुदीर्घ, दीर्घसूत्रिन्, अत्यायत. -ity, *s.* अतिविस्तरः, प्रपंचः, वाग्विस्तरः-प्रपंचः, बाहुप्रपंचः; दीर्घसूत्रता, अतिविस्तारः. -ly, *adv.* विस्तरशः, अतिविस्तरेण, सप्रपंचं.

Prologue, *s.* प्रस्तावना, आमुखं, प्रास्ताविकी विज्ञप्तिः; 'benedictory p.' नांदी.

Prolong, *v. t.* दीर्घीकृ 8 U, प्र-वि-तन् 8 U, वि-प्र-सृ c., विस्तॄ c., आयम् 1 A or c. 2 व्याक्षिप् 6 P or विलंब् c.; 'a p. ed note' तानः. -ation, *s.* विस्तारः, विततिः *f.*, आयतिः, दीर्घीकरणं.

Prolusion, *s.* *See* **Prelude.**

Promenade, *v. i.* विहृ 1 P, विचर् 1 P, विहारार्थं परिभ्रम् 1, 4 P. -*s.* विहारः, परिभ्रमणं. 2 विहारस्थानं.

Prominent, *a.* प्रधान, मुख्य, श्रेष्ठ, मुख्य, विशिष्ट, परम; *See* **Principal.** 2 सुव्यक्त, सुप्रकाश, सुव्यक्त, सुस्पष्ट. 2 उन्नत, उदग्र, उत्तुंग, प्रलंब, सापीड, उद् प्र.; *See* **Projecting.** -ly, *adv.* प्राधान्येन, विशेषतः, सुप्रकाशं, सुस्पष्टं, उन्नतं. -**Prominence,** *s.* प्राधान्यं, विशिष्टता, श्रेष्ठता, उत्कर्षः, प्रकर्षः. 2 उन्नतिः *f.*, उत्सेधः, उत्तुंगता, आभोगः.

Promiscuous, *a.* प्र-सं-कीर्ण, संकुल, अविविक्त, निर्विशेष, अपरिच्छेद्य, अभेद्य, संमिश्रित; 'p. union' संकरः, सांकर्यं. -ly, *adv.* निर्विशेषेण, संकीर्णं, अभेदेन, अक्रमेण, अपरिच्छेदेन. -ness, *s.* संकीर्णता, संकुलता, अभेदः, संकरः.

Promise, *v. t.* सं-प्रति-आ-श्रु 5 P, प्रति-ज्ञा 9 A, (with dat. of persons); स्वी-अंगी-कृ 8 U, अभ्युपगम् 1 P, अभ्युप-इ 2 P, संविद् 2 A, संगृ 6 A, उर (ऊ) रीकृ, उररीकृ, परि-,पण् 1 A; 'the plan p. s to succeed' उपायः सफलो भवेदित्यनुमीयते or आशंसे; 'a p. ing boy' वर्धिष्णुर्बालः, आशानिबंधनं. -*s.* प्रतिज्ञा, समयः, सं-प्रति-श्रवः, वचनं, संविद् *f.*, नियमः, संगरः, संकेतः, अभिसंधा, अभ्युपगमः, स्वीकारः, उरीकारः, अंगीकारः, परिपणनं. 2 आशा, आशंसा; 'hollow p.' सुधावचनं, शब्दपांडित्यं, 'breaking a p.' प्रतिज्ञा-वचन-भंगः, संविद्-व्यतिक्रमः; विसंवादः; keep or fulfil a p.' प्रतिज्ञां पा c. (पालयति) or पुष् c., *See* **Keep, Fulfil:** 'p. breaker प्रतिज्ञालंघिन्-व्यतिक्रामिन्, विसंवादिन्; give a p. orally' वाचा प्रतिज्ञा, वाग्दानं कृ. -ory, *a.* प्रतिज्ञाविशिष्ट.

Promontory, *a.* उदग्रभूमि *f.*, भूशिरस्, नासिका.

Promote, *v. t.* वि-,वृध् c., उपकृ 8 U, पुरस्कृ, प्रवृत् c., साध् c., उपचि 5 U, प्रयुज् 10; (a person) सं-,उन्नम् c. (नमयति), उन्नतिं नी 1 P or प्राप् c., पदं वृध् c. पदोत्कर्ष-प्रतिपत्तिं-प्राप् c., अधिकपदे नियुज्. 3 **Prompt,** q. v. -er, *s.* प्रवर्तकः, उपकर्तृ *m.* *See* **Patron.** -ion, *s.* उपकारः, पुरस्कारः, प्रवर्तनं, साहाय्यं, वर्धनं, वृद्धि *f.*, उपचयः, उन्नतिः, उत्कर्षः, पदवृद्धिः, पदोन्नतिः, प्रतिपत्ति *f.*, श्रेष्ठपदप्राप्ति *f.* -ive, *a.* प्रवर्तक, साधक, उपकारिन्.

Prompt, *a.* सत्वर, अविलंब; क्षिप्र, अविलंबित, अदीर्घसूत्र, (of persons) उद्यत, उद्युक्त, अविलंबिन्, आशुकारिन्, प्रत्युत्पन्नमति, सप्रतिभ, पटु, उद्यमिन्, उद्योगिन्. -*v. t.* प्र-उत्सह् c., प्रणुद् 6 P or c., प्रेर् 10, प्रवृत् c., प्र-उद्-युज् 10 उत्तिज् c., प्र-चुद् c., आकृ c., उद्दीप् c., उत्था c. (उत्थापयति), प्र-उद्-बुध् c.; 'p. ed by hunger' क्षुद्बोधित. 2 प्र-अनु-बुध् c., सूच् 10. -er, *s.* प्रोत्साहकः, प्रवर्तयितृ *m.*, प्रयोजकः, &c. 2 अनु-प्र-बोधकः, सूचकः; 'who seldom wanted a p.' यः सदा प्रत्युत्पन्नमतिः, प्रयो-

प्रणिधेयः. -ing, s. प्रेरणं, प्रोत्साहनं, उत्तेजनं, &c. 2 सूचना, प्रबोधनं. -ness, -itude, s. औत्सुक्यं, अविलंबः, तत्परता, क्षिप्रता. 2 प्रतिभा, प्रत्युत्पन्नमति f., पटुत्वं 3 उद्यमः, उद्योगः. -ly, adv. सत्वरं, अविलंबेन, क्षिप्रं, सद्यः, आशु, अचिरात्, सपदि, तत्क्षणं.

Promulgate, v. t. प्रकाश् c., वि-,घुष् 10, घुष् 10, प्र-ख्या c. (ख्यापयति); *See* **Proclaim.** -ion, s. प्रकाशनं, घोषणं, कीर्तनं. -or, s. प्रकाशकः, घोषकः.

Prone, a. प्रवण, शील, आलु in comp., उद्यत, उन्मुख, *See* **Inclined, Apt;** 'p. to fall' पतयालु, पातुक, पतनशील. 2 (Bent) नत, नम्र, अधोवदन, अधोमुख-अवाङ्मुख-(खी f.). -ness, s. प्रावण्यं, प्रवृत्ति f., उन्मुखता, शीलता, आलुता in comp. 2 अधोमुखता, नम्रता.

Prong, s. शूलः-लं, कंटकः, अग्रं, शिखा.

Pronoun, s. सर्वनामन् n.

Pronounce, v. t. उच्चर् c., उदीर् c., उदा-व्या-हृ 1 P, गद् 1 P, वद् 1 P प्र-,वच् 2 P, प्र-ख्या 2 P, कृत् 10; 'p. judgment' निर्णयं कथ् 10; उत्तरं दा 3 U, &c. 2 निश्चयेन वद्, दृढं प्रति-ज्ञा 9 A; 'imperfectly p.-ed' ग्रस्त, असंपूर्णोच्चरित, लुप्तवर्ण-पद. -Pronunciation, s. उच्चारणं, उदाहरणं, उदीरणं; 'science of p.' शिक्षा; 'easy of p.' सुखोच्चार्य.

Proof, s. *See* under **Prove.**

Prop, s. आश्रयः, शरणं, आधारः, अवष्टंभः, आ-अव-लंबः-बनं, उपघ्नः. -v. t. धृ 1 P, 10, आ-अव-लंब् 1 A, अवष्टंभ् 9 P; 'a tree that p. s another creeper' उपघ्नतरु.

Propaganda, s. धर्मप्रसारकसंस्था.

Propagate, v. t. विस्तॄ c., प्रसृ c., वि-प्र-तन् 8 U; वि-प्र-सृ c.; (opinions) प्रचर्-रु c., प्रवृत् c. or संचर् c.; प्रचलीकृ, प्रथ् c. 2 परंपरया उत्पद् c. or प्र-सू 2 A, प्रसवपरंपरया जातिं वृध् c. शाखकान् प्रथ् or जन् c. or उत्पद् c. -ion, s. प्र-,वर्धनं, प्रसारः, विस्तारः, वितति f., प्र-,वृद्धि f., प्रचारः-रणं. 2 परंपरोत्पत्ति f., प्रसूतिपारंपर्यक्रमः; प्रजा-संतान-वृद्धि f. -or, s. प्रचारकः, प्रवर्तकः.

Propel, v. t. प्रेर् c., प्र-,क्षिप् 6 P, or c., संचल् c., प्रणुद् 10, सं-,चर् c., क्षुभ् 1 P; *See* **Prompt.**

Propense, a. प्रवण, उन्मुख, आसक्त, उद्यत. -ity, s. प्रवणता, प्रवृत्ति f., उन्मुखता, प्रावण्यं, प्रचारः, शीलता-आलुता in comp.; 'p. to fall' पतयालुता, 'good p.' सुशीलं, साधुवृत्तिः, 'evil p.' व्यसनं, दुर्गुणः, दुःशीलं.

Proper, a. स्वीय, निज, आत्मीय, स्व-आत्म in comp. 2 युक्त, योग्य, उचित, उपपन्न, अनुरूप, न्याय्य, संगत, अनुगुण (णी f.), यथार्ह, यथोचित, वर्ग-स्थ, युक्त, सांगतिक (की f.); oft. ex. by pot. pass. part.; 'to be p.' युज् pass., उपपद् 4 A; 'it is p.' स्थाने, स्थाने शोभिता अस्त्रवेत्ता (V. 1.), स्थाने भवान् आकिंचनत्वे व्यनक्ति (R. v. 16). -ly, adv. युक्तं, उचितं, यथार्हं, सम्यक्, स्थाने, न्यायतः, शास्त्रं, यथायोग्यं, धर्मेण. 2 यथार्थतः, परमार्थतः, तत्त्वतः, वस्तुतः; 'p. speaking' वस्तुतः, यथार्थवृत्त्या. -ty, s. धर्मः, गुणः, लक्षणं, स्वभावः, विशेषः, रूपं, स्वरूपं, धर्मः, सहज-प्रकृति-गुणः. 2 स्वत्वं, स्वाम्यं, अधिकारः, प्रभुत्वं. 3 संपत्ति f., द्रव्यं, अर्थः, धनं, वित्तं, वसु n., विभवः; द्रव्य-अर्थ-जातं, रिक्थं, 'woman's p.' स्त्रीधनं, 'landed p.' भूमिधनं, भूमिः, स्थावर धनं, 'public p.' जन-सामान्य-द्रव्यं, 'p. in cattle' गोधनं. -Propriety, s. युक्तता, औचित्यं, उपपत्ति f., न्यायः, सामंजस्यं, योग्यता, यथार्थता, पात्रता, संगति f., 'p. of conduct' विनयः, मर्यादा, अनतिक्रमः, सुचरितं.

Prophesy, v. t. भावि कथ् 10 or सूच् 10 or प्रबुध् c., अनागतं नि-आ-विद् c.; *See* **Predict.** -Prophecy, s. भाविकथनं-सूचनं, भविष्यद्वादः, आदेशः, भविष्यार्थः, सिद्धादेशः. -Prophet, s. सिद्धः, भविष्यद्वादिन् m., अनागतनिरूपकः, भाविकथकः, अनागतविद्-दर्शिन्; 'saying of a p.' सिद्धादेशः. -ess, s. अनागतदर्शिनी, भविष्यद्वादिनी. -ic, -ical, a. (s.) in comp.

Prophylactic, a. रोगहारिन्-हृत्.

Propinquity, s. संनिधिः, संनिकर्षः, सामीप्यं; *See* **Nearness.**

Propitiate, v. t. प्रसद् c., आराध् c., अनुरंज् c., सांत्व् 10, अनुनी 1 P, प्र-,शम् c. (शमयति), सं-परि-तुष् c. -ion, s. प्रसादनं, आराधनं, अनुरंजनं, सांत्वनं, अनुनयः; प्र-उप-शमः-मनं. -or, s. प्रसादकः, आराधयितृ m., अनुरंजकः &c. -ory, a. शमक, सांत्वक, शांतिकर (री f.), शांतिमत्; 'p. rite' शांतिक्रिया. -propitious, a. सु-प्रसन्न, सदय, अनुकूल, हितकाम - बुद्धि, अभिमुख (खी f.), प्रवणीकृत, अनुग्राहिन्, वरद. 2 शुभ, मंगल, कल्याण (णी f.), शर्मद, शुभंकर. -ly, adv. प्रसन्नं, अनुकूलं, सदयं, साधुमतं. -ness, s. प्रसादः, आनुकूल्यं, आभिमुख्यं; शुभता.

Proportion, s. प्रमाणं, परिमाणं; आनुगुण्यं, आनुरूप्यं, परस्पर-अन्योन्य-संबंधः-अन्वयः-अनुबंधः-सादृश्यं-समता; अन्वयः, संबंधः; संधानं, संयोगः, संमिति f. (of limbs &c.) 2 अंशः, विभागः; *See* **Part. 3** अनुपातः, संबंधसाम्यं; 'in p. to' ex. by अनुगुण, अनुसार, अनुरूप, प्रमाणतः, अनुसारेण, यथा in comp.; 'in p. to one's strength' यथाशक्ति, शक्त्यनुसारेण, शक्तितः; 'spend

in p. to your gains' आयप्रमाणेन व्ययं कुरु; 'p. of limbs' अंगसंयोगः, अवयवसंगतिः. -v. t., -ate, v. t. अनुरूपी-सदृशी-कृ 8 U, समीकृ, संमा 3 A, 2 P. -al, a. समप्रमाण, परस्परानुगुण. -ate,-able,-ed, a. अनुरूप, अनुगुण, सदृश, संमित, सम, तुल्य, अनुसारिन्; 'with jars p. to their size (strength)' स्वप्रमाणानुरूपैर्घटैः (S. 1), 'her body beautiful, being p.' चतुरस्रशोभि तस्या वपुः (K. 1, 32). -ately, -ably, adv. अनुरूपं-पेण, अनुगुणं, अनुसारेण, सदृशं, यथाप्रमाणं, यथाभागशः.

Propose, v. t. प्र-स्तु 2 U, उपन्यस् 4 U, उपक्षिप् 6 P, प्रति-ज्ञा 9 A, सूच् 10, कर्तव्यं निर्दिश् 6 P or अभि-धा 3 U. 2 उद्दिश्, आकांक्ष् 6 P; *See* **Intend.** -al, s. प्रस्तावः, उपन्यासः, उपक्षेपः, अभिधानं, प्रतिज्ञा, वचनं, कर्तव्यनिर्देशः. -ition, s. **Proposal**, q. v. 2 प्रतिज्ञा, सिद्धांतः, प्रमेयं.

Propound, v. t. प्रति-पद् c., उपन्यस् 4 U, उपक्षिप् 6 P, निर्दिश् 6 P, प्रति-ज्ञा 9 A.

Proprietor, s. स्वामिन् m. प्रभुः, ईशः, पतिः, अधिकारिन् m. *See* **Owner.** -ship, s. स्वाम्यं, प्रभुत्वं, स्वामित्वं, अधिकारः. -**Proprietary**, a. स्वाम्यधीन, प्रभुनिष्ठ, स्वामिगत; 'p. right' स्वाम्यं, अधिकारः, स्वत्वं.

Propulsion, s. प्रेरणा, चोदना.

Prorogue, v. t. व्याक्षिप् 6 P. (नियतकालं यावत्) विसृज् 6 P or त्यज् 1 P. -**Prorogation**, s. कार्यत्यागः-निवृत्ति f., व्याक्षेपः.

Proscribe, v. t. घोषणापूर्वं दंडं आदिश् 6 P or बहिष्कृ 8 U or निर्वस् c., 'here is Jivasiddhi being disgraced and p.-ed from the city' एष जीवसिद्धिः सनिकारं नगरान्निर्वास्यते (Mu. 1). 2 निषिध् 1 P, निवृ c. -**Proscription**, s. सघोषण दंडाज्ञा.

Prose, s. गद्य. -a. गद्यात्मक, गद्यरूप, गद्य in comp -**Prosaic**, a. गद्यरूप, गद्यात्मक, गद्य in comp. 2 नीरस, विरस, रस-सत्त्व-हीन.

Prosecute, v. t. (नित्यं-अनवरतं) प्रवृत् c., अनुसृ 1 P, अनु-ष्ठा 1 P, अनु-सेव् 1 A, निर्वह् c., अनुशील् 10; 'p. studies' अध्ययनक्रममनुसृ; 'p. one's efforts' अनवरतं उद्यम् 1 A or प्रयत् 1 A; 'p. one's undertaking' प्रारब्धं उद्वह् 1 P, प्रतिपन्नं निर्वह् c. 2 अभियुज् 7 A, 10, अभिशंस् 1 P; सूच् 10, निविद् c. -ion, s. अनुशीलनं, प्रवर्तनं, नित्यानुष्ठानं, नित्यप्रवृत्ति f., निर्वाहणं, अविरतानुसरणं. 2 अभियोगः, निवेदनं; 'p. of effort' नित्योद्योगः; 'p. of study' नित्याध्ययनं, अध्ययनक्रमः.

-or, s. निर्वाहकः. 2 अभियोक्तृ m., वादिन् m., अर्थिन् m., अभिशंसकः.

Proselyte, s. परधर्माश्रयिन्, स्वधर्मत्यागिन्, पक्षांतर-मतांतर-ग्राहिन्; *See* **Convert.** -ize, v. i. स्वधर्मं ग्रह् c., -ism, s. मतांतरग्रहणं, धर्मांतरस्वीकारः.

Prosody, s. छंदस् n., छंदःशास्त्रं. -al,-ical, a. छांदस (सी f.), छंदः in comp. -ian, s. छंदःशास्त्रज्ञः.

Prospect, s. आलोकः, दर्शनं, चक्षुर्विषयः, दृग्गोचर-प्रदेशः-विषयः. 2 आयति f., उत्तरापेक्षा; 'he has good p.s before him' शुभा तस्यायतिः. 3 आशा, प्रत्याशा, आशंसा, अपेक्षा. -ive, a. उत्तर, उत्तरकालीन, भाविकालभाव्य, उत्तरकालसापेक्ष; *See* **Future.** -ively, adv. उत्तरकालापेक्षया.

Prosper, v. i. सं-ऋध् 4, 5 P, प्र-वि-वृध् 1 A, स्फाय् 1 A, एध् 1 A, प्र-उप-चि pass., समृद्धि-वृद्धिं या 2 P or उप-इ 2 P; 'I hope your (commercial) business is p.-ing' अपि प्रचीयंते संव्यवहाराणां लाभाः (Mu. 1). 2 सिध् 4 P, सं-पद् 4 A, सफलीभू 1 P, कृतार्थीभू. -v. t. वृध् c., प्र-उप-चि 5 U. एध् c., उपकृ 8 U, अनुग्रह् 9 P, सफलीकृ, साध् c., सिद्धिं नी 1 P. -ity, s. सं-, ऋद्धि f., संपद् f., संपत्ति f., अभ्युदयः, श्रीः, लक्ष्मीः, वि-, भूति f., सौभाग्यं, वैभवं, पुण्योदयः, ऐश्वर्यं; 'time of p.' संपत्-समृद्धि-उदय-कालः-समयः. 2 समृद्धिः, उत्कर्षः, उन्नति f., उदयः, प्र-उप-चयः, वि-सं-वृद्धि f., साफल्यं, कृतार्थता, सिद्धि f. 3 क्षेमः-मं, कौशल्यं, कल्याणं, शुभं, शिवं, हितं, भद्रं. -ous, a. समृद्ध, श्रीमत्, समृद्धिमत्, लक्ष्मीवत्, सश्रीक, ऐश्वर्यशालिन्; (state &c.) वर्धिष्णु, प्र-उप-चीयमान, एधमान, वर्धमान; 'in p. days' संपत्सु, अभ्युदयकाले, भूतिसमये, समृद्धिकाले. 2 सफल, सिद्ध, कृतार्थ, सिद्धार्थ; (happy) सुस्थ, निरापद्, क्षेम, कुशल, कल्याण (णी f.), शिव, भद्र, मंगल, शुभ, सौभाग्यवत्, धन्य. -ously, adv. समृद्ध्या, अभ्युदयेन, सुसंपदा, सौभाग्येन, शुभं, भद्रं.

Prostitute, s. वेश्या, वेशवधूः, गणिका, वारपण्य-स्त्री-अंगना-योषित्, भोग्या, सामान्यस्त्री, रूपाजीवा; (false to her husband) पुंश्चली, बंधकी, असती, कुलटा, स्वैरिणी, पांसु(शु)ला, धर्षिणी, इत्वरी. -v. t. निंद्यकर्मार्थं प्र-उप-विनि-युज् 1 A, 10 or व्यापृ c. -ion, s. वेश्याजीवः, वेश्या-गणिका-वृत्ति f., वारसेवा, बंधकीत्वं, पौंश्चल्यं, &c.

Prostrate, a. प्रणत, भूमिगत, साष्टांगप्रणत-पतित, 'lie or fall p.' *See* (v.); 'p. on the bed' शयनगत, शयने अधमुखशय, 'lying p. at the feet' चरण or पाद-पतित or प्रणत. 2 अवसन्न, क्षीण. -v. t. (Oneself)

दंडप्रणामेन-साष्टांग-पूर्व-नम् 1 P or प्रणिपत् 1 P, दंडवत् पत्, शीर्षैः प्रणम् or प्रणिपत्. 2 नि-अव-पत् c.; भूमिं नय् c. (भ्रमयति). 3 (Strength) अवसद् c; ध्वंस् c., प्र-वि-नश् c., क्षु 1 P; क्षि 1, 5 P. **-ed,** *a.* प्रणिपतित, भूमिगत, निपतित, &c. 2 क्षीणबल-शक्ति, हृत or नष्ट-शक्ति or ओजस्. **-ion** *s.* दंडप्रणामः अष्टांगप्रणामः-प्रणिपातः, साष्टांगप्रणामः-वंदनं, प्रणिपातः, प्रणामः. 2 (Of spirits) अवसादः, ग्लानि *f.*, विषण्णता, उद्वेगः; 'p. of strength' शक्तिपातः-क्षयः, सत्त्वहानि *f.*

Protect, *v. t.* रक्ष् 1 P, अव् 1 P, परि-,त्रै 1 A, गुप् 1 P, पा 2 P, पा c (पालयति), परि-प्रति°-, वृ c. 2 संवृध् c., परि-,पुष् c. **-ion,** *s.* गोपनं, गुप्ति *f.*, पालनं, त्राणं, रक्षा, रक्षणं, अभ्युपपत्ति *f.*, संवर्धनं, परिपोषणं. 2 शरणं, आ-संश्रयः, आ-अव-लंबः, आधारः; 'go for p.' आश्रि 1 U, आलंब् 1 A, शरणं गम् 1 P or प्रपद् 4 A; 'paper granting p.' अभयपत्रं. **-or,** *s.* रक्षकः, गोप्तृ *m.*, पालयिता, रक्षिता, रक्षिन्, पालकः, त्राता, शरणं, शरण्यः; आश्रयः, पः-पालः in comp. **-Protege,** *s.* आश्रितः, पालित., उपजीविन् *m.*, पोष्यः, शरणं गतः.

Protend, *v. t.* विस्तृ c., प्रसृ c.; *See* **Extend.**

Protest, *v. i.* दृढं-दृढोक्तिपूर्वं-वद् 1 P or आख्या 2 P; 'p. against' दृढं विरुद्धं वद्, दृढं-दृढोक्तिपूर्वं नि-प्रति-षिध् 1 P, दृढं असंमतिं प्रकाश् c. or ज्ञा c.; 'I strongly p. against this order' अयमादेशोऽन्याय्य इति सनिश्चयं वदामि 'p. in writing' असंमतिलेखं-विप्रतिपत्ति-पत्रं-प्रकाश् c. **-s.** दृढनिषेधवाक्यं, अस्वीकार-असंमति-वादः, विरुद्धवादः, अस्वीकारप्रकाशनं; 'written p.' असंमतिपत्रं. **-ant,** *s.* रोमीयमतविरुद्धः. **-ation,** *s.* दृढवचनं-उक्तिः-वादः, विरुद्धवचनं, निषेधोक्तिः.

Proteus, *s.* कामरूपः.

Prototype, *s.* आदर्शः, मूलं, मूलप्रतिमा.

Protract, *v. t.* विलंब् c., व्याक्षिप् 6 P; *See* **Delay.** 2 प्र-,तन् 8 U; प्रसृ c., दीर्घीकृ 8 U. **-ed,** *a.* सुदीर्घ, विलंबित, चिरस्थित, चिर in comp.; 'p. note' तानः; 'p. sound' प्लुतः. **-ion,** *s.* विलंबः, व्याक्षेपः.

Protrude, *v. i.* प्रः-निः-सृ 1 P, निर्गम् 1 P, उद्भिद् pass., प्रलंब् 1 A, बहिर्वृत् 1 A or स्था 1 P. **-v. t.** Causal of roots above. **-ing,** *a.* बहिर्लंब, बहिःस्थ. **-Protrusion,** निःसरणं, उद्भेदः, प्रलंबनं. **-Protuberance,** *s.* वि-,स्फोटः, पिटकः, शोथः, शोफः, श्वयथुः, (on the skin). 2 प्रलंबनं, उत्सेधः, उत्तुंगता, आभोगः, उन्नति *f.* **-Protuberant,** *a.* उन्नत, उत्तुंग, उच्छ्रित, उच्छून, प्रलंब; 'having p. breasts' तुंग-उन्नत-स्तनी, घन-कुंभ-स्तनी, oft. ex. by उत्सेधः; पयोधरोत्सेधविशीर्णसंहति (K. v. 8) the continuity being broken by her p. breasts.' **-Protuberate,** *v. i.* प्रलंब् 1 A; *See* **Project,-ing** &c.

Proud, *a.* *See* under **Pride.**

Prove, *v. t.* उप-प्रति-पद् c., साध् c., वि-भू c., प्र-मा 3 A, 2 P, प्रमाणीकृ 8 U, सत्याकृ, स्था c. (स्थापयति). 2 प्र-,दृश् c., सूच् 10, निर्दिश् 6 P, प्रकाश् c., व्यंज् 7 P or c.; 'he was p. ed guilty' अपराधी स्थापितः; 'good men p. their usefulness by deeds, not by words' प्रकटोहि फलेन साधवो न तु कंठेन निजोपयोगिता (N. ii. 48), कर्मणा न तु वाङ्मात्रेण दर्शयंति. 3 परीक्ष् 1 A निरूप् 10, निर्णी 1 P, निश्चि 5 U, प्रति-इ c.; *See* **Test.** **-v. i.** सं-उत्-पद् 4 A, वृत् 1 A, सं-,भू 1 P; निर्णी-निश्चि-प्रतीपass.; 'the tilled ground p. ed a treasure indeed' कृष्टा भूमिरेव कोषस्थाने बभूव, कोषत्वमापद्यत. **-er,** *s.* साधकः, विभावकः. **-Proof,** *s.* साधनं, प्रमाणं, उपपत्ति *f.*, उप-प्रति-पादनं; 'written p.' लेख्यप्रमाणं, साधनपत्रं; 'burden of p.' साधनधर्मः, क्रियानिर्णयः; 'the burden of p. lies on both parties' द्वयोरपि वादिनोः क्रिया प्राप्नोति (V. M. 6.). 2 लक्षणं, चिह्नं. 3 परीक्षा-क्षणं, निर्णयः, निश्चयः; 'to put to the p.' परीक्ष्. 4 स्थूल-प्रथम-मुद्रणं. 5 अभेद्यता, अहार्यता, अविकार्यता; 'p. against advice' उपदेशाहार्य; 'water p.' जलेनाभेद्य. **-less,** *a.* निष्प्रमाण, साधनहीन.

Provenance, *s.* उत्पत्ति *f.*, संभवः, उद्गमस्थानं.

Provender, *s.* पाथेयं; खाद्यं, पशुभोज्यं, शुष्कतृणादि *n.*

Proverb, *s.* जनप्रवादः, लोकवादः, आभाणकः, जनोक्ति *f.*, न्यायः, वचनं, उक्तिः. **-ial,** *a.* लौकिक (की *f.*), लोकप्रसिद्ध-प्रचलित, लोक-जन in comp., न्यायरूप. **-ially,** *adv.* लोके, जनश्रुत्या.

Provide, *v. t.* (पूर्वं) सं-,युज् 7 U, 10, संधा 3 U, प्र-उप-कॢप् c., समाधीकृ 8 U, द्रव्यसामग्रीं उपपद् c. or वि-धा 3 U or कृ; *See* **Prepare.** 2 (पूर्वं) नियम् 1 P, प्रति-ज्ञा 9 A, परिपण् 1 A, संकेतं-समयं-कृ; निर्दिश् 6 P; *See* **Enjoin, Ordain;** (for, against) gen. ex. by अर्थं-अर्थे in comp.; 'should p. wealth against times of want' आपदर्थं धनं रक्षेत्; 'who p. s for the future' अनागतविधाता; 'p. against' निवारणाय सज्जीभू, प्रतिकारोपायं कॢप् c. **-ed,** *a.* (पूर्वं) संयुत, परिकल्पित, युक्त, उपेत, सहित, अन्वित,

सनाथ, सनाथीकृत, 'he is duly p. for' तस्य समुचिताः संविधाः कृताः; उपकरणसामग्रीयुक्तः, अन्नपानादियुक्तः. 2 पूर्वं निर्दिष्ट, परिकल्पित, पूर्वं संकेतित; 'p. that' यदि, चेत्, एतेन समयेन. **-ence**, *s.* विधिः, परमेश्वरः; *See* **God.** 2 सुविमर्शः, दूरदर्शित्वं, पर्यवेक्षणं, पूर्वविवेकः-विचारः, सुसमीक्षा, दूर-दीर्घ-दृष्टि *f.* **-ent**, *a.* दूरदर्शिन्, विमृश्यकारिन्, विवेकिन्, दूर-दीर्घ-दृष्टि. **-ential**, *a.* ईश्वर-विधातृ-कृत-प्रयुक्त-वहित. **-entially**, *adv.* विधिवशात्, ईश्वरेच्छया, दैवात्, दिष्ट्या. **-ently**, *adv.* सविवेकं, सुसमीक्ष्य, सुविमृश्य, दूरदृष्ट्वा. **-Provision**, *s.* परिकल्पनं, विधानं, उपपादनं. 2 पूर्वोपायः, पूर्वकल्पना, संविधा-धानं. 3 समयः, संकेतः, प्रतिज्ञा, पणः, नियमः, अभिसंधिः. 4 (P. s.) सामग्री, संभारः, संचयः, संग्रहः, साहित्यं, संविधा, उपस्करः, उपकरणजातं; (for journey) पाथेयं, भोज्यं, भक्ष्यं, भक्ष्यादिसामग्री, भोजनसंविधा; (for army) वीवधः. *-v. t.* **Provide**, q. v. **-al, -ary**, *a.* सामयिक (की *f.*), अल्पकालस्थायिन्, आपात in comp., आपाततः नियुक्त. **-ally**, *adv.* आपाततः, समयानुरूपेण, स्तोककालं. **-Provisory**, *a.* सप्रतिज्ञ, सामयिक. **-Proviso**, *s.* *See* (*s.*) (3).

Province, *s.* विषयः, राष्ट्रं, देशः, वर्गः, मंडलं. 2 नियोगः, कार्यं, कर्मन् *n.*, कर्तव्यं, अधिकारः. 3 प्रकरणं, अंशं, विषयः (fig. also), (सर्वलौकिकस्याभ्यवहार्यमेव विषयः V. 3. **-ial**, *a.* देशीय, देश्य, राष्ट्रीय, राष्ट्रिक-दैशिक-(की *f.*), देश-राष्ट्र in comp. *-s.* देशस्थः, ग्रामस्थः. **-ialism**, *s.* ग्रामीणभाषा, असंस्कृतभाषा.

Provoke, *v. t.* प्र-,कुप् c., क्रुध् c., कोपं-कोपं-उत्पद् c. or उद्दीप् or उत्तिज् c. 2 उत्पद् c., जन् c., (जनयति), प्रवृत् c., उत्तिज् c.; *See* **Excite, Cause.** 3 क्षुभ् 5 P, आह्वे 1 A. **-ing**, *a.* प्रकोपक, उद्दीपक, उत्तेजक, क्रोधावह, संतापकारिन्, संतापक. **-ingly**, *adv.* Ex. by (*v.*). **-Provocation**, *s.* प्रकोपः, क्रोधोद्दीपनं, कोपोत्तेजनं, कोपकारणं-हेतुः. 2 उद्दीपनं, उद्बोधनं. **-Provocative**, *a.* उद्दीपक, उद्बोधक. *-s.* दीपनं, अग्निवर्धनं, क्षुद्बोधनं, प्ररोचनं.

Provost, *s.* अध्यक्षः, अधिकारिन् *m.*, अधीशः.

Prow, *s.* पोताग्रभागः,

Prowess, *s.* शौर्यं, वीर्यं, वि-परा-क्रमः, पौरुषं, ओजस् *n.*, रणोत्साहः-शौर्यं; 'personal p.' बाहुवीर्यं, भुजबलं.

Prowl, *v. i.* (भक्ष्यार्थं); परि-,भ्रम् 1, 4 P, पर्यट् 1 P. **-ing**, *s.* परिभ्रमणं, पर्यटनं.

Proximate, *a.* समीप, निकट, आसन्न, संसक्त, सन्निकृष्ट. **-ly**, *adv.* समीपं, संसक्तं. **-Proximity**, *s.* सन्निधिः, सन्निकर्षः, सान्निध्यं, नैकट्यं, संसक्ति *f.*; *See* **Nearness.**

Proximo, *adv.* आगामिनि (मासे)

Proxy, *s.* प्रतिनिधिः-पुरुषः, प्रतिहस्तः; 'by p.' प्रतिनिधिद्वारा.

Prude, *a.* (Woman) अतिविनीता, विनयाभिमानिनी, सूक्ष्माचारनिष्ठा. **-ry**, *s.* अतिविनीतता, विनयाभिमानः, मिथ्याविनयः. **-ish**, *a.* *See* (*a.*).

Prudent, *a.* दूरदर्शिन्, विमृश्य-समीक्ष्य-कारिन्, विवेकिन्, दूर-दीर्घ-दृष्टि, परिणामदर्शिन्, सदसद्विवेकिन्; बुध, मनस्विन्, नीतिज्ञ, विज्ञ, प्र(प्रा)ज्ञ, मनीषिन्, सावधान, कृतधी; *See* **Wise**, also. 2 (Of acts) समीचीन, श्रेयस्, वरं *ind.* **-ial**, *a.* सविवेक, विवेक-समीक्षा-प्रयुक्त. **-ly**, *adv.* विमृश्य, समीक्ष्य, सविवेकं, दूरदर्शितया, परिणामदृष्ट्वा, प्रज्ञवत्. **-Prudence**, *s.* दूरदर्शिता, दूर-दीर्घ-दृष्टि *f.*, विवेकः, प्रसमीक्षा, समीक्ष्य-विमृश्य-कारित्वं, सदसद्विवेकः, नीति *f.*, मनीषा, मति-बुद्धि *f.*

Prune, *v. t.* अग्राणि लू 9 U or अव-छिद् 7 P or निकृत् 6 P. **-ing**, *s.* अवच्छेदः, निकृंतनं; 'p.-knife' विटपच्छेदनी छुरिका.

Prurigo, Prurient, *See* **Itch, -y.**

Pry, *v.* (Into) सूक्ष्मं निरीक्ष् 1 A or निरूप् 10 or दृश् 1 P; निपुणं अनुसं-धा 3 U or अन्विष् 4 P or चर्च् 6 P. **-ing**, *s.* सूक्ष्म-निरूपणं-अन्वेषणं, सूक्ष्मचर्चा.

Prythee, *adv.* अयि, ननु, (ननु मां प्रापय पत्युरंतिकं K. IV. 32).

Psalm, *s.* स्तोत्रं, गेयं, गीतं, भक्ति-धर्म-गीतं. **-ist**, *s.* गीत-स्तोत्र-कारः. **-Psalter**, *s.* गीतसंहिता-संग्रहः.

Pseudo, prefix, Ex. by मिथ्या, कपट, कूट-छद्म, कृतक, कृत्रिम in comp.; *See* **False.** **-nym**, *s.* कृतकनामन् *n.*

Pshaw, *interj.* धिक्, अपेहि.

Psychic, *a.* आध्यात्मिक.

Psychology, *s.* अध्यात्मविद्या, आन्वीक्षिकी.

Puberty, *s.* यौवनं, वयस् *n.*, तारुण्यं, यौवनदशा-अवस्था, प्रौढदशा; 'a woman attained to p.' स्त्रीधर्मिणी, उदक्या; *See* under ***Menstrual.*** **-Pubescent**, *a.* प्राप्तयौवन, प्रौढ, तरुण.

Public, *s.* लोकाः, जनाः, प्रजाः, प्रकृतयः, (pl.); लोकः, जनः, प्रजा; 'in p.' प्रकाशं, लोकसमक्षं, प्रकटं, सर्वप्रत्यक्षं. *-a.* प्रजा-लोक-संबंधिन्, साधारण (णी *f.*,) सामान्य, सर्वजनीन-य, सार्वलौकिक (की *f.*), लोक-जन-जन in comp.; 'p. odium' जनद्वेषः, 'p. good' लोकहितं; 'p. property' जनद्रव्यं. 2 प्रसिद्ध, लोक-जन-प्रसिद्ध, सर्वत्र प्रथित, बहुलीकृत, लोकविश्रुत, प्रकाशीकृत,

सार्वलौकिक (की *f.*) 3 प्रकाश, अगूढ, अच्छन्न, अविविक्त, सर्वप्रकाश, राज in comp.; 'p. road' राजमार्गः; 'p. sale' प्रकाशविक्रयः; 'p. house' शुंडा, पानं, शुंडापानं, सुरालयः, सुरापणः; *See* under **Liquor**; 'p.-minded', 'p.-spirited' उपकारशील, जनहितबुद्धि, सर्वजनहितपरायण, लोकहित, जनहितैषिन्. **-an,** *s.* शौंडिकः, सुरापणिकः. 2 कर-शुल्क-ग्राहिन् *m.* **-ity,** *s.* प्रकाशता, प्राकाश्यं, प्रख्याति *f.*, प्रसिद्धि *f.*, विश्रुति *f.*, जन-लोक-प्रसिद्धिः, स्पष्टता; 'give p.' **Publish,** q. v. **-ly,** *adv.* प्रकाशं-शतः, प्रासरं, प्रकटं, सर्वप्रकाशं-संमुखं-समक्षं; अगूढं, अच्छन्नं, सुव्यक्तं, स्पष्टं. **-Publish,** *v. t.* प्रकाश् c., प्रथ् 10, ख्या c. (ख्यापयति), प्र-वि-घुष् 10, ज्ञा c. (ज्ञापयति), प्रचर् c., घुष् c., प्रकाशीकृ 8 U, प्रकटीकृ, आविष्कृ, प्रकटयति, (:D.), प्रकटी-प्रसिद्धी-कृ; (books &c.) प्रकाश् c. **-er,** *s.* प्रकाशकः, प्रकाशयितृ *m.*, ख्यापकः. **-Publication,** *s.* प्रकाशनं, घोषणं, ख्यापनं. 2 प्रकाशितपुस्तकं-ग्रंथः.

Pucker, *v. t.* संकुच् 1 P, आकुंच् c., संवृ 1 P, पुटीकृ 8 U. **-s., -ing,** *s.* संकोचः, पुटः, वलि-ली *f.* **-ed,** *a.* संकुचित, पुटीकृत. 2 **Wrinkled,** q. v.

Puddle, *s.* पंकिलजल, पंकगुल्मः, पंकजलाशयः, **-v. t.** आविली-कलुषी-कृ 8 U; *See* **Spoil.**

Pudency, *s. See* **Modesty.**

Pudendum, Pudenda, *s.* योनि *f.*, भगं, उपस्थः.

Puerile, *a.* बालिश, बालोचित, बालेय, बाल-शिशु-योग्य. **-ity,** *s.* बालिश्यं, बालधर्मः.

Puerperal *a.* प्रसव-प्रसूति in comp. **-Puerperous,** *a.* बालप्रसविनी.

Puff, *v. t.* ध्मा 1 P, आ-उप-°, उद्-,श्वि c., (lit. & fig.); वातेन पूर् 10, उद्-हन् 2 P, स्फाय् c. (स्फावयति). **-v. i.** श्वस् 2 P, कृच्छ्रेण श्वस्, उद्-ध्मा. 2 वा 2 P. 3 फुत्कृ 8 U, मारुतं निःसृ c. 4 श्वि-उच्छून्-ध्मा-pass., स्फीत-आध्मात-उच्छून- *a.* भू 1 P; 'do not p. up, when praised' स्तूयमाना नोत्सिच्यंते (Ka. 329). **-s.** श्वासः, मुखमारुतः. 2 फूत्कारः, फूत्कृतं. 3 वात्या, वातवेगः; *See* **Gust.** 4 अतिप्रशंसा. **-ed,** *a.* आध्मात, उच्छून, स्फीत, उद्धत, मारुतपूर्ण, श्वासपूरित; 'p. up with pride' दर्पाध्मात, उत्सिक्त, मदोद्धत, उद्धत. **-ing,** *s.* श्लेषकः, *See* **Pride.**

Pug-faced, *a.* वानरवदन, कपिमुख.

Pug-nose, *s. See* under **Flat.**

Pugilist, *s.* मुष्टियोधः, मल्लः. **-Pugilism,** *s.* मुष्टि-मल्ल-युद्धं, मुष्टीमुष्टि युद्धं.

Pugnacious, *a.* कलह-युद्ध-प्रिय, रणोत्सुक, युयुत्सु, रण-युद्ध-कलह-काम. **-Pugnacity,** *s.* युयुत्सा, कलहेच्छा, कलह-युद्ध-कामः.

Puisne, *a.* अवर, अवरपदस्थ.

Puissant, *a.* शूर, विक्रांत, वीर्यवत्, प्रबल. **-Puissance,** *s.* शौर्य, वि-परा-क्रमः, वीर्य; *See* **Bravery.**

Puke, *v. i.* वम् 1 P, छर्द् 10. **-s.** (वांतिकृत्) औषधं.

Pulchritude, *s. See* **Beauty.**

Pule, *v. i.* बालकवत् रु 2 P or कूज् 1 P.

Pull, *s.* कर्षणं, आकर्षः; ग्रहणं, धरणं. **-v. t.** कृष् 1 P, आ-सं-°. 2 ग्रह् 9 U, आ-दा 3 A, धृ 1 P, 10. **-down,** नि-,पत् c., अधः पत् c., अवकृष्; (in strength) अव-सद् c., अप-चि 5 U, क्षि 5 P, अपकृष्. **-off,** अप-नी 1 P, अप-उत्-कृष्, अवतॄ c., उन्मुच् 6 P, अपहृ 1 P; निष्कृष्, निर्हृ. **-out,** उद्धृ, निष्कृष्, वि-उत्-पट् 10, उत्खन् 1 P, निर्हृ; (hair) उत्-, लुंच् 1 P. **-towards,** आ-समा-कृष्. **-up,** उन्मूल् 10, उद्धृ, उच्छिद् 7 P, उत्पट्; *See* **Eradicate. -ing,** *s.* आकर्षणं, ग्रहणं, &c.; 'p. by the hair' केशग्रहः-हणं; 'mutual p. of the hair' केशाकेशि युद्धं.

Pullet, *s.* कुक्कुटशावः.

Pulmonary, *a* क्लोम-फुप्फुस in comp.

Pulp, *s.* मज्जा, सारः, वसा. 2 गर्भः, बीजं. **-ous,-y,** *a.* मज्जाबहुल, मज्जागुणक, मांसल, मज्जोपम, कोमल.

Pulpit, *s.* पीठं, आसनं.

Pulse, *s.* नाडि-डी *f.*; (beating) नाडीस्फुरणं-स्पंदनं; 'feel the p.' नाडीं स्पृश् 1 P or स्पृश् 6 P. or परीक्ष् 1 A, 'the p. is quick' लघुगतिः नाडी; 'the p. is low on account of phlegm' कफात्संवृत्तिश्रिया (नाडी). 2 वैदलः, शमी-शिंबी-धान्यं; शमीजः. **-Pulsate,** *v. i.* स्पंद् 1 A, स्फुर् 6 P; *See* **Throb. -ion,** *s.* गति *f.*, स्फुरणं, आघातः, स्पंदनं; 'p. of the heart' हृदयोद्घर्षः.

Pulverize, *v. t.* चूर्ण् 10, क्षुद् 7 P, पिष् 7 P. **-Pulverulent,** *a.* चूर्ण-क्षोद-मय (यी *f.*).

Pummel, *s.* त्संरु.

Pump, *s.* जलोत्कर्षयंत्रं, जलोत्क्षेपणं. **-v. t.** (जलादि) उत्तुल् 10, उत्क्षिप् 6 P. 2 (Out) निष्कृष् 1 P, रिच् 7 P, or c., रिक्तीकृ 8 U.

Pumpkin, *s.* कूष्मांडः-डकः, कर्कारुः.

Pun, *s.* श्लेषः **-v. t.** श्लेषं प्रयुज् 7 A, 10.

Punch, *s.* प्रहारः, आ-अभि-घातः. 2 विदूषकः, भंडः. 3 वेधनिका. —*v. t.* तड् 10 or प्रहृ 1 P. 2 **Perforate** q. v.

Punchy, *a.* स्थूलकाय; *See* **Fat.**

Punctilio, *s.* सूक्ष्मता, अतिसौक्ष्म्यं; सूक्ष्मविषयः-नियमः. —**Punctilious,** *a.* सूक्ष्मनियमनिष्ठ-निरत, सूक्ष्माचारनिष्ठ, अतिसूक्ष्मदृष्टि *f.* —**ness** *s.* सूक्ष्मनियमनिष्ठा; अतिसूक्ष्मदृष्टि *f.*

Punctual, *a.* सामयिक (की *f.*), संकेतसमय-निष्ठ अनुवर्तिन्; 'let us be p.' सामयिका भवामः (M. 1). —**ity,-ness,** *s.* समय-संकेत-पालनं-निष्ठा-अनुवर्तनं, सामयिकता. —**ly,** *adv.* यथासमयं-संकेतं-काले.

Punctuate, *v. t.* विरामचिह्नानि लिख् 6 P: चिह्नैः अंक् 10.

Puncture, *v. t.* कीलाग्रेण व्यध् 4 P or भिद् 7 P. —*s.* वेधः-धनं, *See* **Prick.**

Pungent, *a.* तीव्र, तीक्ष्ण, प्रखर, तिग्म, उग्र, चंड. 2 मर्मभिद्, अरुंतुद, मर्माविद्, कटु. 3 (To the taste) तीक्ष्ण, तिक्त, तीव्र. कटु, उष्ण. —**Pungency,** *s.* प्रखरता. उग्रता. चंडता, तीक्ष्णता. कटुता, तीव्रता &c.

Punish, *v. t.* दंड् 10, शास् 2 P, (with two acc.); निग्रह् 9 P, दम् c. (दमयति); तड् 10 (by beating); 'p. ed him by an unjust death' अन्यायेन तं जघान. अन्यायवधं तमदंडयत्; 'should p. as a thief' चौरदंडेन दंडयेत् (Y. II. 269). 2 **Plain,** q. v. —**er,** *s.* शास्तृ *m.*, शासकः, दंडयिता. —**ment,** *s.* दंडः, शासनं, निग्रहः; साहसं; दमः. —**Punitive, Punitory,** *a.* दंड in comp.

Punt, *s.* तरालुः, तरांधुः.

Puny, *a.* क्षुद्र, अल्पाल्प, अतिलघु.

Pupil, *s.* शिष्यः, छात्रः, अंतेवासिन् *m.*, अध्येतृ *m.*, विद्यार्थिन् *m.* 2 कनीनिका, तारा, तारका. —**age,** *s.* शिष्यदशा-अवस्था. अंतेवासित्वं.

Puppet, *s.* पुत्रिका, पांचालिका; *See* **Doll;** 'p.-show' पुत्रिकाक्रीडा.

Puppy, Pup, *s.* कुक्कुरशावः-शिशुः.

Purblind, *a.* हतदृष्टि, ईषदंध.

Purchase, *v. t.* क्री 9 U. 2 व्ययेन-श्रमेण आप् 5 P or लभ् 1 A. —*s.* क्रयः. 2 क्रीतद्रव्यं. 3 संग्रहणं. ग्राहः; 'p.-money' क्रयमूल्यं, अर्घः, मूल्यं. —**er,** *s.* क्रयिन् *m.*, क्रेतृ *m.*

Pure, *a.* वि-, शुद्ध, शुचि (in all senses); स्वच्छ, विशद, निर्-वि-अ-मल, प्रसन्न, अनाविल, अकलुष. 2 पुण्य, अनघ, निष्पाप, साधु, अपाप, अलिप्त, निष्कलंक, अकल्मष. 3 पवित्र, पावन, मेध्य. परि-,पूत, प्रयत, तीर्थ in comp. 4 केवल, शुद्ध, मात्र in comp. 5 अदुष्ट, अभ्रष्ट, असंसृष्ट. अविकृत. 6 (Language) अपभ्रंशहीन-रहित, असंकीर्ण. 7 (Woman) सती, साध्वी, अज्ञातव्यवाया, कुमारब्रह्मचारिणी, अक्षता, अक्षतयोनिः, कुमारी; 'of p. descent' सद्वंशज, शुद्धान्वय; 'of p. heart', 'p.-minded' शुद्धात्मन्, विमलात्मन्, शुद्धमति, शुद्धहृदय; प्रयतात्मन्; 'to be p.' शुध् 4 P. —**ly,** *adv.* निर्मलं, विशुद्धं, शुचि; निष्पापं, &c.; मात्रं, केवलं &c. —**ness,-Purity,** *s.* वैमल्यं, वि-,शुद्धि, *f.*, शुद्धता, प्रसादः, वैशद्यं, शुचिता, शौचं, पुण्यता, साधुता, अपापता, पवित्रता, पूतता, साध्वीत्वं, &c. —**Purify,** *v. t.* परि-,पू 9 U or c., शुध् c., वि-परि-,° शुचीकृ 8 U, निर्मलीकृ, पवित्रीकृ, संस्कृ; प्र-,मृज् 2 P, निर्णिज् 3 U, प्रक्षल् 10, धाव् 10. —**ed,** *a.* परि-,पूत, शुद्ध, शोधित, प्रक्षालित, धौत, निर्णिक्त, &c.; 'p by penance' प्रयतात्मन्. —**ication,** *s.* परि-,पूति *f.*, वि-परि-शुद्धि *f.*, शौचं, संस्कारः, पावनं, शोधनं, निर्मलीकरणं, प्रक्षालनं, धावनं, मार्जनं. —**icative,-icatory,** *a.* पावन, पवित्र, पावक, तीर्थ in comp.; अघ-पाप-नाशिन्, अघमर्षण; *See* **Pure,** 'p. rites' शांतिक्रिया, संस्कारः. —**ing,** *a.* पावन, पावक, पवित्र, &c.

Purge, *v. t.* शुध् c., वि-,रिच् 7 P or c., मलं निःसृ c. or शुध् c. 2 परि-,पू 9 U, शुध् c., 2 पापं-अघं-क्षुप्; *See* **Purify.** —*s.* वि-,रेचनं-कं; उदरशोधनं. —**ation,** *s.* वि-, रेचनं, वि-,रेकः, शोधनं, शुद्धि *f.* —**ative,** *a.* वि-,रेचक-न, सारक, शोधन. —*s.* वि-, रेचनं-कं, सारकं. —**atory,** *s.* शोधक, पावन, अघनाशन-मर्षण. —*s.* पापमोक्ष स्थानं.

Purlieu, *s.* *See* **Border.**

Purloin, *v.* *See* **Rob, Steal.**

Purple, *a.* धूम्र, धूमल, नीललोहित, धूम्रवर्ण. —*s.* धूम्रः, धूमलः, धूम्रवर्णः, नीललोहितः. —*v. t.* धूम्रीकृ 8 U. —**ish,** *a.* आधूम्र, ईषद्धूमल.

Purport, *s.* भावः, अभिप्रायः, तात्पर्यं, अर्थः आशयः, भावार्थः, तात्पर्यार्थः. —*v. t.* अभिप्र-इ 2 P; उद्दिश् 6 P, *See* **Intend, Mean.**

Purpose, *s.* हेतुः, अभिप्रायः, आशयः, अर्थः, संकल्पः, उद्देशः, तात्पर्यं, चिकीर्षितं, इच्छा, आकूतं. आकांक्षा, कार्यं, मति-बुद्धि *f.*, धीः; *See* **intention;** 'fixed p.' स्थिर or दृढसंकल्पः or निश्चयः; 'of unfailing p.' दृढ सत्य-संकल्प, स्थिरधी-मति; 'to no p.' निरर्थकं, वृथा, मुधा, व्यर्थं, निष्फलं; 'who has effected his p.' कृती, कृतार्थः, कृतकृत्यः; 'for the p. of' ex by अर्थ-अर्थे, हेतोः, निमित्तं-त्ते, in comp., कृते (with gen. or by dat.); 'for what p.' किमर्थं, किमुद्दिश्य, केन हेतुना. —*v. t.* अभिप्र-इ, 2 P, उद्दिश् 6 P, संकल्प c., इष् 6 P; *See*

intend. -ly, ' on p. ' *adv.* कामतः, बुद्धि-बोध-पूर्वं, ज्ञानतः, बुद्ध्वा, साभिप्रायं.

Purse, *s.* धनभस्त्रिका-कोषः, ग्रंथिः. 2 धनं; *See* **Wealth;** p. cutting ग्रंथिच्छेदः-भेदः; p. pride' धनगर्वः-दर्पः अभिमानः, ' p.-proud ' धनोन्मत्त, वित्तगर्वित, धनदृप्त, -*v. t.* कोषे नि-धा 3 U or निविश् c. 2 **Contract,** q. v.

Pursue, *v. t.* अनुसृ 1 P, अनुगम्-धाव्-व्रज् 1 P, अनु-या 2 P, अनुवृत् 1 A, अनुक्रम् 1 U, 4 P. 2 अनु-ष्ठा 1 P, आचर् 1 P, आचर् 1 P, नि-,सेव् 1 A, आश्रि 1 U, आ-स्था 1 P. 3 प्रवृत् c., निर्वह् c., सततं प्रणी 1 P; *See* **Prosecute.** 4 आप् desid. (ईप्सति), लभ् desid. (लिप्सते); ' p. one's way ' मार्गं आक्रम्, वह् 1 P; *See* **Follow.** -**er,** *s.* अनुसारिन् *m.*, अनुधावकः, अनुगामिन् *m.* -**Pursuit,** *s.* अनुसरणं-धावनं-गमनं; अन्वेषणं, मार्गणं. 2 अनुष्ठानं, आचरणं, निषेवणं, अभिनिवेशः, अनुशीलनं, प्रवृत्ति *f.*, लिप्सा, अर्जनप्रयत्नः, निष्ठता-परता in comp. 3 व्यापारः, व्यवसायः, उद्योगः, उद्यमः, आरंभः, व्यवहारः, कार्यं, प्र-,वृत्तिः; ' literary p. s. 'विद्याभ्यासकार्याणि, ज्ञानसंपादनारंभाः. -**Pursuant,** *a.* अनुवर्तिन्, अनुसारिन्, अनुरोधिन्, अनुरूप. -**ly,** *adv.* अनुरूपं, अनुसारेण-तः, अनुरोधेन, यथा in comp. -**Pursuance,** *s.* अनुसरणं, वर्तनं-गमनं-रोधः; ' in p. of ' अनुरूपं, अनुसारेण, &c. -**Pursuivant,** *s.* अनुचरः, दूतः.

Pursy, *a* स्थूल-ह्रस्व, उच्छून, स्फीत. 2 दुःश्वासिन्, कृच्छ्रश्वास.

Purtenance, *See* **Appertenance.**

Purulent, *a.* पूयपूर्ण-मय (यी *f.*), पूयस्राविन्, सपूय. -**Purulence,** *s.* पूयपूर्णता, सपूयता.

Purvey, *v. t.* उपकरणानि उपक्लृप् c., सं-भृ 1, 3 U or संयुज् 7 U,10; *See* **Provide.** -**ance,** *s.* भोजनपरिकल्पनं-संभारः-सामग्री. 2 परिकल्पनं, संभारः, संविधा-धानं. -**or,** *s.* भोजनाधिकारिन् *m.*, आहाराधिकृतः.

Purview, *s.* विषयः.

Pus, *s.* पूयः-यं, दूष्यं, पूयरक्तं.

Push, *v.* (हस्तादिना) प्रेर् c., संचल् c., प्रक्षिप् 6 P, प्रणुद् 10, प्रेर् c., प्रणुद् 6 P or c.: *See* **Drive.** 2 तड् 10, प्र-हृ 1 P; आव्यध् 4 P, प्रति-अभि-हन् 2 P, आहन् 2 U; ' p. aside ' अपसृ c., बहिष्कृ 8 U, निःसृ c.; 'p. forward' प्रणुद् c., प्रचल् c., प्रसृ c.; ' p. afar ' उत्सृ c. -*s*, -**ing,** *s.* प्रसारणं, प्रक्षेपः, प्रेरणं-णा, प्रचोदना. 2 ताडनं, आघातः, प्रहार अभ्याघातः 3 वेगः, प्रयत्नः. -**ing,** *a.* उद्य ...र, उद्योगिन्, साहसशील, प्रगल्भ, साहसिन्.

Pusillanimous, *a.* कृपण, दीन, क्षुद्रमनस्, कृपणबुद्धि-मति, लघुचेतस्, पामर, भीरुहृदय, कातर, कापुरुष, क्लीब. -**Pusillanimity,** *s.* कार्पण्यं, दैन्यं, क्लीबता, कातर्यं, भीरुता, कृपणमतित्वं, क्षुद्रता.

Puss, Pussy, *s. See* **Cat.**

Pustule, *s.* **Pimple,** q. v. -**ous,** *a.* स्फोटपूर्ण.

Put, *v. t.* स्था c. (स्थापयति), नि-अभ-धा 3 U, आरुह् c., धा 3 U, कृ 8 U, ऋ c. (अर्पयति), निविश् c., वि-,न्यस् 4 P. 2 आ-समा-युज् 7 U, 10. 3 **Incite,** q. v.; ' p. to death ' हन् 2 P or c., मृ c., व्यापद् c.; *See* **Kill,** ' p. to flight ' वि-द्रु c., 'p. in mind ' स्मृ c., प्र-अनु-बुध् c.; ' p. in order ' यथाक्रमं-यथातथं-रच् 10 or स्था c. or विन्यस्, सज्जीकृ; ' p. in writing ' पत्रे निविश् c., लेख्ये आरुह् c. -**about,** परिवृत् c. -**aside,** by, अपास् 4 U, क्षिप् 6 P, त्यज् 1 P: *See* **Abandon.** 2 परि-,रक्ष् 1 P; सं-चि 5 U. -**away,** अप-निः-सृ c., निष्कस् c., बहिष्कृ, व्याक्षिप् 6 P, विलंब c. -**down,** भूमौ निधा, अवतॄ c., निक्षिप्. 2 भञ्ज् c., विलुप् c., उच्छिद् 7 P; *See* **Destroy, Overthrow.** 3 (In writing) पत्रे लिख् 6 P. or निविश् c. or आरुह् c. -**forth,** प्रसृ c. 2 आविष्कृ, व्यंज् 7 P, व्यक्तीकृ, प्रकाश् c., प्र-, दृश् c. 3 उपक्षिप्, उपानी, उपन्यस्, उदाहृ 1 P. 4 उद्-भिद् c.; ' a creeper having p. forth foliage ' सञ्जातपल्लवा लता (R. III. 7). -**off** व्याक्षिप्, विलंब c., अतिपत् c. 2 उन्मुच्, अवतॄ c., अपनी, उच्छद् 10, अपभ्रंश् 4 P. 3 निराकृ, निःसृ c.; *See* **Discard, Discharge.** 4 (From land) अपगम्, अपया, अपसृ 1 P; ' the boat p. off ' मुक्ता नौः (D. K. II. 6). -**on,** वस् 2 A, परिधा; धृ 1 P, 10, सं-व्ये 1 P; प्रसाध् c., आच्छद्, पि आ-मुच् 5 U; 'p. on. armour' संनह् 4 P. 2 ग्रह् 9 U, स्वीकृ, धृ, भृश् c. 3 संक्रम् c., संचर् c. 4 आसंज् c.; निविश् c. -**out,** विसृज् c., प्रसृ c., वितन् 8 U. 2 (Eyes &c.) सं-,उद्धृ, वि-उत्-पट् 10. 3 निर्वा c. (वापयति), प्र-उप-शम् c. (शमयति). 4 विलक्षीकृ, व्रीडया आकुलीकृ, *See* **Embarrass.** 5 निःसृ c., बहिष्कृ. 6 प्र-विनि-युज् 7 A, 10; 'p. out at interest' वृद्धिलाभाय विनियोजित. -**over,** अधिकृ c., अधि-ष्ठा c. 2 **Put off,** q. v. -**to,** **Expose,** q. v.; ' p. to the sword ' खड्गेन छिद् 7 P or हन् 2 P; ' p. to sea ' नावं मुच्; ' p. to a stand ' स्तंभ् 9 P. -**together,** संयुज्; संधा, सं-बंध् 9 P. -**up,** उद्वह् 1 P. वस् 1 P; *See*

Lodge. 2 (with) सह् 1 A, क्षम् 1 A; *See* **Bear.** 3 व्यक्तीकृ, प्रकाशं स्था c., प्रदृश् c.; 'an article p. up for sale' क्रय्यं मूल्यं; 'p. up to' प्रयुज् c., प्रोत्सह् c.

Putative, *a.* प्रसिद्ध, अभिमत.

Putrify, *v. i.* पूतिभू 1 P, पूय् 1 A, दुर्गंध-*a.* भू; वि-,गल् 1 P,वि-ली 4 A. —*v. t.* पूतीकृ 8 U, गल् c., विली c. **—action,** *s.* पूति *f.*, दुर्गंधता, पूतिगंधः, गलनं, विलयः. **—Putrid, Putrescent,** *a.* पूतिगंधि, उग्रगंध, दुर्गंध, विगलित, विलीयमान. **—ness, Putrescence,** *s.* पूतिः, दुर्गंधः, पूतिगंधः.

Puzzle, *v. t* व्या-,मुह् c., सं-वि-भ्रम् c. (भ्रमयति), आकुलीकृ 8 U, व्यस् 4 U; *See* **Confuse, Perplex.** —*s.* कूटं, प्रहेलिका, प्रवह्लिका. 2 व्या-मोहः, भ्रांति *f.*, संभ्रमः, वैक्लव्यं, व्याकुलता, व्यग्रता. **—ed,** *a.* मूढ, भ्रांत, व्यस्तचित्त, आकुलमनस्, किंकर्तव्यतामूढ. **—ing,** *a.* भ्रम-मोह-कारिन्, संभ्रमप्रद.

Pygmy, *s.* ह्रस्वः, खर्वः, वामनः. —*a.* ह्रस्व, खर्व, वामनमूर्ति.

Pyramid, *s.* सूच्यग्रस्तंभः, **—al,** *a.* सूच्याकार; सूच्यग्र, शिखरिन्, शुंडाकृति.

Pyre, *s.* चिता, चित्या, चिति *f.*

Pyretic, *a.* ज्वरसंबंधिन्. —*s.* ज्वरघ्नोऽगदः, ज्वरोपायः.

Pyrites, *s.* स्वर्णमाक्षिकं.

Pyrrhonist, *s.* नास्तिकः, मिथ्यादृष्टिः.

Q

Quack, *s.* कुवैद्यः, दांभिकः, छद्मवैद्यः, मिथ्याचिकित्सकः. 2 हंसनादः-रवः. —*v. i.* हंसवत् नद् 1 P or रु 2 P. **—ery,** *s.* कुचिकित्सा; मिथ्याभिमानः. 2 **Boast,** q. v.

Quadrangle, *s.* चतुर्भुजः, चतुष्कोणः; (of a house) प्रकोष्ठः, चत्वरं, संजवनं, चतुःशालं. **—Quadrangular,** *a.* चतुष्कोण, चतुरस्र.

Quadrant, *s.* चतुर्थभागः, पादः. 2 वृत्तपादः.

Quadrate, *s. See* **Square.**

Quadratic, *a.* चतुरस्रीय. 2 (equation) वर्गसमीकरणं.

Quadrature, *s.* चतुःसंस्थानं.

Quadrennial. *a.* चातुर्वार्षिक (की *f.*).

Quadrilateral, *a.* चतुर्भुज, चतुःपार्श्व

Quadripartite, *a.* चतुर्विध.

Quadrisyllable, *s.* चतुरक्षरं.

Quadruped, *s.* चतुष्पदः (दी *f.*), चतुष्पाद्.

Quadruple, *a.* चतुर्गुण. —*v. t.* चतुर्गुणीकृ 8 U.

Quaff, *v. t.* (सतृष्णं) पा 1 P, उद्-चुलुंप् 1 P. **—er,** *s.* अतिपायिन् *m.*

Quagmire, *s. See* **Marsh.**

Quail, *s.* वर्तकः, वर्तिका, लावः. —*v. i.* कंप् 1 A, वेप् 1 A. 2 वि-अव-सद् 1 P, क्षि pass.; म्ली 4 A.

Quaint, *a.* अपरूप, विलक्षण, असंगत. 2 विदग्ध, चतुर, अतिसूक्ष्म. **—ly,** *adv.* विलक्षणं, असंगतं.

Quake, *v. i.* कंप् 1 A, उद्विज् 6 A, त्रस् 1, 4 P; (with abl.). —*s.* कंपः-पनं, उद्-प्र-कंपः, वेपथुः.

Qualify, *v. t.* योग्य-उचित-क्षम-*a.* कृ 8 U; ex. by 'q. ed' 2 नियम् 1 P, परिच्छिद् 7 P, परि-मा 3 A, 2 P, निबंध् 9 P. 3 **Moderate,** q. v. **—ed,** *a.* योग्य, क्षम, समर्थ, पर्याप्त, कर्मक्षम, अलंकर्मीण. 2 गुणिन्, गुणोपेत, गुणसंपन्न. 3 नियत, परिच्छिन्न, समर्याद; *See* **Limited.** **—ication,** *s.* योग्यता, क्षमता, पात्रता, औचित्यं, गुणविशिष्टता. 2 गुणः, पात्रत्वं, विशिष्टगुणः. 3 परिच्छेदः, मर्यादा, नियमनं, नियतत्वं, परिमाणं. **—Quality,** *s.* गुणः. 2 भावः, धर्मः, गुणः, स्वभावः, प्रकृति *f.*; स्व-,रूपं, लक्षणं, विशेषभावः-धर्मः-लक्षणं, शीलं; शक्ति *f.* 3 कुलीनता, श्रेष्ठ-विशिष्ट-पदं, प्रतिष्ठा, गौरवं, उत्कृष्टपदं. 4 प्रकारः, जाति *f.*, *See* **Kind;** 'good q.' गुणः, सद्गुणः, सद्भावः, 'having good q. es' गुणिन्, गुणवत्, गुणोपेत, गुणयुक्त, सद्गुण; 'bad q.' दुर्गुणः, अपगुणः; 'inherent q. of a thing' निसर्गधर्मः, वस्तुशक्तिः; 'men of q.' कुलीनजनाः, अभिजात-कुलीन-वर्गः.

Qualm, *s.* वमनेच्छा, विवमिषा. 2 मनस्तापः, अनुशयः, अनुतापः. **—ish,** *a.* विवमिषु.

Quandary, *s. See* **Difficulty.**

Quantity, *s.* परिमाणं, प्रमाणं, मानं, मात्रा, अंशः, भागः. 2 मात्रा. 3 राशिः. 4 (Large) संचयः, ओघः, पूगः, पुंजः, राशिः, संग्रहः; 'a great q. of' प्रभूत, प्रचुर, बहु, विपुल; 'great q.' बाहुल्यं, प्राचुर्यं, बहुभागः, भूयिष्ठांशः; ex. by बहु, प्रचुर, विपुल (**Much,** q. v.); 'in large q. es' बहुशः, बाहुल्येन, प्राचुर्येण; 'small q.' स्तोकांशः, अल्पभागः; अल्पं, स्तोकं, अल्पमात्रं; 'in small q. es' अल्पशः, स्तोकांशेन; 'long q.' दीर्घः; 'short q.' ह्रस्वः; 'known q.' व्यक्तराशिः; 'unknown q.' अव्यक्तराशिः; 'positive, negative, q.' धन-ऋण-राशिः; 'what q. of' कियत्.

Quantum, *s.* परिमाणं, मात्रा, कल्पितभागः.

Quarantine, *s.* आगमनसंसर्गनिषेधः.

Quarrel, *s.* कलहः, कलिः, विवादः, विसंवादः, विप्रतिपत्ति *f.*, वाक्कलहः, वाग्युद्धं, विप्रलापः; द्वंद्वं, वैरं. **–v. i.** विवद् 1 A, विप्रलप् 1 P, विसंवद् 1 P, विप्रतिपद् 4 A, वैरायते-कलहायते (D.), कलहं कृ 8 U, युध् 4 A. **–er,** *s.* विवादिन् *m.*, कलहकारी. **–some,** *a.* कलह-कलि-प्रिय, विवादशील, विसंवादिन्, कलह-कलि-पर, कलहकारिन्, युयुत्सु, विवादार्थिन्.

Quarry, *s.* आकरः, ख(खा)नि-नी *f.*, पाषाणस्थानं-भूमि *f.* 2 आमिषं, मार्गितजंतुः. **–v. t.** खन् 1 P; *See* **Dig.**

Quartan, *a.* चातुर्थिक.

Quarter, *s.* पादः, तुर्यः, तुरीयः, अर्धार्धं, तुरीय-चतुर्थ-भागः; 'a rupee and a q.' सपादरूपकः. 2 दिश्-शा, आशा, काष्ठा, ककुभ्, हरित्; *See* **Direction;** 'in intermediate q.' अपदिशं; 'guardian of a q.' दिक्पालः, लोकपालः; 'guardian elephant of the q.' दिग्गजः, 3 प्र-,देशः, उद्देशः, स्थानं, दिक्-शा, दिग्भागः, दिग्देशः, दिगंतः; 'from various q.s' नानादिग्देशात्, नानादिगंतेभ्यः, नानादिग्भ्यः; 'in every q.' चतुर्दिशु. 4 (Q. s) वासः, वसति *f.*, निकेतनं, वासस्थानं, निवेशः, कटकः-कं; 'head q. s' सेनापतिनिवेशः, कटकः. 5 दया, कृपा, जीव-प्राण-दानं; 'give q.' दयां कृ 8 U, अभयं दा 3 U. 6 (Of night) यामः, प्रहरः. 7 मासत्रयं, त्रिमासं, वत्सरपादः; 'to close q. s' बाहूबाहवि, हस्ताहस्ति, मिथःप्रत्यासन्न-*a.*; 'they two came to close q. s' तौ बाहूबाहवि व्यासृजेताम् (Si. xviii. 12). **–v. t.** चतुर्धा विभज् 1 U or खंड् 10 or छिद् 7 P. 2 वस् c., निविश् c. **–v. i.** निवस् 1 P, निविश् 6 A, अध्यास् 2 A. **–ly,** *a.* त्रैमासिक (की *f.*), पादिक (की *f.*). **–adv.** मासत्रयांते, प्रतित्रिमासं.

Quarto, *s.* चतुःपत्रकं.

Quash, *v. t.* मृद् 9 P, पराजि 1 A, पराभू 1 P. 2 खंड् 10, निवृत् c., विलुप् 6 P or c., उच्छिद् 7 P, निरस् 4 U.

Quasi, Ex. by कृ, कल्प, देशीय, in comp.

Quaternion, *s.* चतुष्टयं, चतुष्कं.

Quatrain, *s.* चतुष्पदश्लोकः.

Quaver, *v. i.* **Tremble,** q. v. 2 भग्नस्वरेणगै 1 P. **–s.** स्वरभंगः, कंपस्वरः.

Quay, *s.* घट्टः, घट्टी, तीर्थं, उत्तरणस्थानं.

Quean, *s.* *See* **Prostitute.**

Queen, *s.* राज्ञी, महिषी, देवी (title of address), राजपत्नी-महिषी; 'q.'s metal' कांस्यं. **–like, –ly,** *a.* राज्ञीसदृश (शी *f.*), अनुरूप.

Queer, *a.* विलक्षण, असंगत, अपरूप, अद्भुत; *See* **Odd.**

Quell, *v. t.* शम् c. (शमयति), प्र-उप-,° निवृत् c., विनश् c., उच्छिद् 7 P. 2 दम् c. (दमयति), वशीकृ 8 U, परा-अभि-भू 1 P, पराजि 1 A.

Quench, *v. t.* (Thirst) शम् c. (शमयति), प्र-उप-,° छिद् 7 P, निवृत् c., अपनी 1 P. 2 निर्वा c. (वापयति), प्र-उप्-शम् c. **–ing,** *s.* शमनं, शांति *f.*, वि-,च्छेदः.

Querulous, *a.* दुःखित, परिदेवनाकुल, विलापिन्, परिदेविन्, विलापशील, शोकमग्न, दुःखात्मक. **–ly,** *adv.* सविलापं. **–ness,** *s.* विलपनशीलता.

Query, *s.* *See* **Question.**

Quest, *s.* अन्वेषणं, अनुसंधानं, मार्गणं, निरूपणं; 'in q. of prey' भक्ष्यार्थं.

Question, *s.* प्रश्नः, अनुयोगः, पृच्छा; 'put a question to' प्रच्छ् 6 P, अनुयुज् 7 A; 'you have put me a good q.' सम्यक् पृष्टोस्मि भवता. 2 जिज्ञासा, निरूपणं, परीक्षणं, अनुसंधानं, विचारः-रणा. 3 संदेहः, संशयः, वितर्कः, विकल्पः, आ-,शंका; 'here a q. arises' अत्रेदं प्रष्टव्यं. 4 वि-,वादविषयः-पदं-वस्तु-आस्पदं, विचारविषयः, &c.; 'call in q.' विचर् c., (आज्ञा गुरूणां ह्यविचारणीया R. xiv 46); the topic in q.' प्रस्तुत-प्रकृत-विषयः; 'the q. arose as to &c.' इति-विवादः-प्रश्नः-समुपस्थितः. **–v. t.** प्रच्छ्, अनुयुज्, ज्ञा desid. (जिज्ञासते); 'ascetics may be q. ed without reserve' अनिर्वचनीयानुयोगास्तपस्विजनाः (S. 1). 2 परीक्ष् 1 A, निरूप् 10, अनुसंधा 3 U, विचर् c. 3 आशंक् 1 A, न प्रति-इ 2 P, न विश्वस् 2 P, वितर्क् 10, विकल्प् 1 A; *See* **Doubt. –able,** *a.* विचार्य, विशंक्य, शंकनीय, संदिग्ध, शंकार्ह, संदेहशंका-पदं. **–ably,** *adv.* साशंकं, संदिग्धं. **–ary,** *a.* प्रश्नात्मक. **–er,** *s.* पृच्छकः, प्रष्टृ *m.*, अनुयोक्तृ *m.*, अनुयोगिन् *m.*, जिज्ञासुः. **–less,** *adv.* निःसंशयं, निःशंकं.

Quibble, *s.* वाक्छलं, वक्रोक्ति *f.*, वक्रभणितं, कैतववादः, अप-व्यप-देशः, अपलापः, अपह्नवः. **–v. i.** अपलप् 1 P, वक्रं भण् or वद् 1 P, अपदिश् 6 P, वाक्छलं कृ 8 U. **–er,** *s.* अपलापिन् *m.*, वक्रोक्तिवादिन् *m.* **–ing,** *s.* *See* (*s.*).

Quick, *a.* शीघ्र, त्वरित, द्रुत, क्षिप्र, सत्वर, अविलंबित, तूर्ण; 'q.-wit' प्रत्युत्पन्नमतिः &c.; 'q. as thought' मनोजवेन, संकल्पस्य त्वरयेव. 2 तीक्ष्ण, सूक्ष्म, तीव्र, शीघ्रग्राहिन्, आशुकारिन्. 3 तीव्र, शीघ्र-बुद्धि-मति, सचेत, चपल; *See* **Sharp.** 4 सजीव, चल, स्पंदमान; 'q. with child' चलितगर्भा, आपन्नसत्त्वा, *See* **Pregnant;** 'be q.', 'q., q.' त्वरस्व, त्वरस्व; 'q.-lime'

चूर्णजलं, तप्तचूर्ण; 'q. sand' अस्थिर-पुलिनं-सैकतं; q.-sight' तीक्ष्ण-सूक्ष्म-दृष्टि *f.*; 'q.-silver' पारदः; See **Mercury**, 'q.-witted' शीघ्र-तीक्ष्ण-बुद्धि-मति, प्रत्युत्पन्नमति. *-adv.* **Quickly**, q. v. *-s.* मर्मन् *n.*, मर्मस्थानं-देशः; 'piercing to the q.' मर्मस्पृश्-भिद्-च्छिद्-आविध्. **-en**, *v. t.* त्वर् c. (त्वरयति), गतिं वृध् c. 2 जीव् c., उच्छ्वास-*a.* कृ 8 U, जीवं दा 3 U. 3 उद्दीप् c., उत्तिज् c., शो 4 P, प्रचक्ष् c., वृध् c.; *See* **Sharpen**. *-v. i.* त्वर् 1 A, द्रुततरं गम् or चल् 1 P. 2 जीवित्वं-चैतन्यं-आप् 5 P, सजीवीभू. 3 स्पंद् 1 A, चल् 1 P, स्फुर् 6 P. **-ening**, *a.* जीवद्, उद्दीपक. **-ly**, *adv.* शीघ्रं, सत्वरं, त्वरितं, तूर्णं, लघु, आशु क्षिप्रं, द्रुतं. अविलंबं, अविलंबितं, चपलं, अरं, शीघ्र-क्षिप्र- द्रुत in comp.; 'going q. ' द्रुतगामिन्, शीघ्रगति. 2 अह्नाय, सपदि, सद्यः; झटिति, अचिरात्, अचिरेणैव. **-ness**, *s.* शीघ्रता, तीक्ष्णता, &c.

Quiescent, *a.* निश्चल, निश्चेष्ट, स्थिर, अचल, विरत, शांत. **-Quiescence**, *s.* निश्चलता, चेष्टाभावः, शांति *f.*, &c.

Quiet, *a.* शांत, प्र-उप-°, निश्चल, अचल, स्थिर, निष्कंप; अक्षुब्ध, अव्याकुल, स्तिमित, निर्वृत, निवृत्तवायु, (sea); विरत, विश्रांत. 2 सौम्य, मृदु. अचंड, अनुग्र; *See* ***Mild***. 3 स्वस्थ. निर्विघ्न, अबाध, निरुपद्रव, निरुपप्लव, निरुद्वेग, अभंग. 4 निःशब्द, तूष्णीक; 'keep q.' मौनमवलंबस्व, जिह्वां धारय, तूष्णीं भव, जोषमास्स्व. *-s.* स्थिरता, निश्चलत्वं, शांति *f.*, शमः, प्र-उप-°, विश्रामः, स्वास्थ्यं, निरुपद्रवता, निर्वातत्वं, अक्षोभः, निरुपप्लवता, &c. *-v. t.* सांत्व् 10, प्र-उप-शम् c. (शमयति), निवृत् c., विरम् c., विश्रम् c., स्थिरीकृ 8 U. **-ism**, *s.* शमः, वैराग्यं, निवृत्तिमार्गः. **-ist**, *s.* विरागिन् *m.* **-ly**, *adv.* शांतं, शांत्या, निराकुलं, अव्याकुलं, अक्षुब्धं, स्वास्थ्येन, अनुग्रं, अचंडं; तूष्णीं, निःशब्दं. **-ness**, **-itude**, *s.* शमः; *See* (*s.*).

Quill, *s.* पक्षः, पर्णं; (for writing) कलमः, लेखनी; (of a lute) कोणः, शारिका, कोणः; (of a porcupine) शलं, शललं-ली.

Quilt, *s.* तूला, तूलिका, तूलिकाप्रच्छदः-संस्तरः; प्रच्छदपटः. *-v. t.* तूलादिना निषिव् 4 P.

Quinary, *s.* पंचकं. *-a.* पंचरूप, पंचक.

Quindecagon, *s.* पंचदशभुजः.

Quinquennial, *a.* पंचवार्षिक (की *f.*), पंचवर्षीय.

Quinsy, *s.* श्लेष्मजा रोहिणी, कंठपाकः.

Quintessence, *s.* सारः, तत्त्वं; *See* **Essence**.

Quintuple, *a.* पंचगुण; पंचविध.

Quip, *See* **Taunt**.

Quire, *s.* कागदकल्पः.

Quirk, *s.* **Quibble**, q. v. 2 उपालंभः, अवक्षेपः, विकारः. 3 छंदस् *n.*, मनोलौल्यं; *See* **Fancy**. **-ish**, *a.* चपल, लोलमति.

Quit, *v. t.* त्यज् 1 P, हा 3 P, अपास् 4 U, वि-उत्-सृज् 6 P; *See* **Abandon**; अवसृप् 1 P, निर्गम् 1 P, अप-या 2 P, व्यप-इ 2 P, (with abl.). 2 (Debt) वि-मुच् 6 P or c., शुध् c., निस्तॄ c., निरा-अपा-कृ 8 U. *-a.* वि-,मुक्त, शोधित, निस्तीर्ण. **-tance**, *s.* निष्कृति *f.*, मोक्षः, शुद्धि *f.*, निस्तारः, मुक्ति *f.*, साधनं; 'q. of a spite' वैरशुद्धिः-शोधनं.

Quite, *adv.* सर्वथा, सर्वशः, साकल्येन, निःशेषं. 2 सु-अति pr.; अत्यंतं, अतीव, भृशं; *See* **Exceedingly**.

Quiver, *s.* तूणः-णी, तूणीरः, निषंगः, इषुधिः, उपासंगः. *-v. i.* स्फुर् 6 P, कंप् 1A, स्पंद् 1 A, वेप् 1 A. **-ed**, *a.* तूणिन्, तूणीरभृत्. **-ing**, *a.* कंपमान, वेपमान, कंपित, स्फुरित, सकंप, चंचल, लोल, चपल. *-s.* स्फुरणं, स्पंदनं, कंपः-पनं.

Quixotic, *a.* अद्भुत, विचित्र, असंभव.

Quiz, *s.* उपहासकः, अवक्षेपकः. *-v. t.* उप-अव-हस् 1 P, अवाक्षिप् 6 P.

Quoit, *s.* चक्रं, वलयः-यं. *-v.* चक्रैः क्रीड् 1 P.

Quondam, *a.* पूर्व; *See* **Former**.

Quorum, *s.* निर्दिष्टसंख्या, कार्यनिर्वाहक्षमा संख्या.

Quota, *s.* अंशः, भागः.

Quote, *v. t.* उद्-हृ 1 P, अवतॄ c., उपन्यस् 4 U, उद्-धृ 6 P, उदा-हृ, उप-नी 1 P. **-ation**, *s.* उद्धारः, अवतरणं, उद्धरणं, उपन्यासः, उद्धृत or अवतारित-वाक्यं or लेखः.

Quoth, *v.* आह, वदति, &c.

Quotidian, *a.* दैनंदिन (नी *f.*), प्रात्याहिक (की *f.*); अन्वेद्युष्क.

Quotient, *s.* फलं, गुण्यः; 'by dividing is obtained the q.' भजनेन लब्धो गुण्यः.

R

Rabbit. शशः, शशकः.

Rabble, *s.* प्राकृताः, पृथक्-प्राकृत-जनाः; नीचाः; प्राकृतगणः.

Rabid, *a.* उन्मत्त, संभ्रांत, विक्षिप्तचित्त, वातुल. **-ly,** *adv.* सोन्मादं, उन्मत्तवत्. **-ness,** *s.* उन्मादः, वातुलता.

Race, *s.* अन्वयः, कुलं, वंशः, संतानः, संतति *f.*, वंशावलि-ली *f.*, गोत्रं. 2 जाति, वर्णः. 3 **March,** q. v. 4 चर्या, धावनं. 5 मूलं; 'to run a r.' अहमहमिकया-परस्पराजिगीषया-धाव् 1 P; 'slow and steady wins the r.' मंदोऽप्यविरतोद्योगः सदा विजयभाग्भवेत्, (कूर्मवृत्तिं समास्थाय सर्वत्र विजयी भवेत्); 'r.-course' धावनभूमि *f.*; 'r.-horse' जवाश्वः, जवनः. **-v.** *i* धाव् 1 P; *See* **Run. -ial,** *a.* जातीय, वर्णीय.

Rack, *s.* तीव्रवेदना, यातना, अतिव्यथा; 'put to the r.' अर्द् 1 P or c., संपीड् 10. 2 गवादनी, द्रोणि-णी *f.* 3 संपीडनयंत्रं, प्रमाथयातना-यंत्रं; 'r.-and ruin' उच्छेदः. **-v.** *t.* अत्यंतं पीड् or व्यथ् c. (व्यथयति), यातनायंत्रेण पीड् or प्रमथ् c.

Racket, *s.* कोलाहलः, कलकलः, तुमुलरवः, 2 गुलिकाताडनी. **-y,** *a.* तुमुलकारिन्.

Racy, *a.* सरस, रसवत्; तीक्ष्ण-उग्र-रस.

Radiate, *v. i.* निर्गम् 1 P, समंततः प्रसृ 1 P or उद्-इ 2 P (rays); स्फुर् 6 P, किरणान् विकॄ 6 P or प्रसृ c., दीप् freq. (देदीप्यते). **-ion,** *s.* अंशुप्रसरणं-स्फुरणं, किरणपातनं-विकिरणं. **-Radiant,** *a.* उज्ज्वल, दीप्तिमत्, सुप्रभ, देदीप्यमान, तेजस्विन्; *See* **Bright. -ly,** *adv.* सुप्रभं, अतितेजसा, उज्ज्वलं. **-Radiance,** *s.* प्रभा, दीप्ति *f.*, कांति *f.*, तेजस् *n.*, औज्ज्वल्यं; *See* **Lustre, Light.**

Radical, *a.* मूलं in comp., मौलिक (की *f.*); मौल (ली *f.*). 2 निसर्गज, स्वाभाविक-नैसर्गिक-(की *f.*); *See* **Natural. -ly,** *adv.* समूलं, मूलतः, आमूलं. 2 स्वभावतः, प्रकृत्या, जातितः.

Radish, *s.* मूलकः-कं.

Radius, *s.* त्रिज्या, जीवा; व्यासार्धं, विष्कंभार्धं. 2 (Of a wheel) अरः.

Raff, *s.* *See* **Rabble.**

Raft, *s.* उडुपं, प्लवः; कोलः, तरंडः.

Rafter, *s.* तुला, दीर्घस्थूणा-काष्ठं, दीर्घदारु, गृहस्थूणा

Rag, *s.* वस्त्रखंडः-डं, पटखंडः, चीरं, चीवरं, कर्पटः, न(ल)क्तकः. 2 अजर्र-जीर्ण-वस्त्रं, पटच्चरं; 'dressed in r. s' चीरवासस्, परिहितचीर, कार्पटिक. **-ged,** *a.* जीर्ण, जर्जर.

Rage, *s.* संरंभः, मन्युः, रोषः, कोपः, प्रकोपः; उत्तापः, संतापः, क्रोधावेशः, अमर्षः. 2 उत्कटेच्छा, लालसा, तीक्ष्णता, उच्चंडता, तीव्रता, उग्रता, तिग्मता. **-v.** *i.* नितरां क्षुभ् 4 P, 1 A, कुध्-रुष्-कुप् 4 P, संरंभ-मन्युवशं-गम् 1 P or आप् 5 P, क्रोधाकुल-*a.* भू 1 P. 2 उग्र-चंड-तीक्ष्ण *-a.* भू; 'r. on (of cloud)' गर्ज्. गर्जितिष्ठ. **-ful,** *a.* क्रोधान्वित, कोपाकुल, रुष्ट, कुपित, जातामर्ष संरंभित. **-ing,** संरंभिन्, उग्र, तीक्ष्ण, तीव्र, उच्चंड, वेगवत्.

Raid, *s.* अवस्कंदः, आघातः.

Rail, *v. i.* अव-आ-अधि-क्षिप् 6 P, अप-भाष् 1 A, अपवद् 1 A, आक्रुश् 1 P, शप् 1, 4 U, गर्ह् 1, 10 A, निंद् 1 P, भर्त्स् 10 A; 'r. ing words' आक्षेपवाक्, गर्हणा, निंदावचः. **-v.** *t.* लोहस्तंभैः परिवृ 5 U or परिवेष्ट् 1 A or c., निरुध् 7 U. **-s.** लोहशंकुः-शलाका-तुला; 'r.-way,' 'r.-road' लोहपथः-मार्गः. **-er,** *s.* अवक्षेपकः, निंदकः, निर्भर्त्सकः, अपवादकः, आक्रोशकः. **-ing,** *s.* लोहावरणं, लोहशलाकावृति *f.* 2 अव-आक्षेपः, आक्रोशः, निंदा, निर्भर्त्सना, गर्हणा, अपवादः, उपालंभः, अपभाषणं, तिरस्कारः.

Raiment, *s.* वस्त्रं, वसनं, वासस् *n.*, अंबरं आच्छादनं, वेशः-षः, परिच्छदः; *See* **Cloth, Garment;** 'food and r.' ग्रासाच्छादनं, अन्नवस्त्रं.

Rain, *s.* वृष्टि *f.*, वर्षः-र्षं, पर्जन्यः; 'gentle r.' शीकरासारः; 'heavy r.' अतिवृष्टिः; 'shower of r.' धारासंपातः, धारासारः; (r. s) वर्षाः *f.* (pl.), प्रावृष् *f.*, वर्ष-मेघ-घन-समयः-कालः, मेघागमः, तपात्ययः, वर्षा, कालः; 'r.-bow' इंद्रधनुस् *n.*, इंद्रचापं and similar comp.; सुरधनुः, इंद्रायुधं; 'r.-fall' वर्ष-वृष्टि-पातः; 'r.-water' वृष्टि-वर्ष-जलं. **-v.** *i.* वृष् 1 P, (the subject being 'Indra' 'Sky' or 'Cloud'), जलं सृ or पत् 1 P; 'when it was r. ing gently' मंदं मंदं वर्षति जलधरे-घनने-वासवे, &c.; 'it r. ed in torrents' धारासारैर्-दिर्षभूव; 'to r. off' 'cease to r.' निर्वृष्. **-v.** *t.* वृष्, जलं सृ c. **-y,** *a.* वृष्टिमत्, वर्षिन्, प्रावृषिक (की *f.*); 'a r. day' दुर्दिनं; 'r. season' वर्षाः, प्रावृट्; *See* (*s.*).

Raise, *v. t.* उत्-स्था c. (उत्थापयति), in all senses; उत्तुल् 10, उन्नी 1 P, उच्छ्रि 1 U, उत्कृष् 1 P; उत्क्षिप् 6 P, उद्यम् 1 A, उन्नम् c. (नमयति), उद्-हृ-धृ 1 P, उद्-वह् 2 P: आत्मोद्धृतैरपि रजोभिः (S. 1) 'r-ed by themselves'; आ-अधि-रुह् c.; oft. ex. by उत् in comp.; 'having r. ed

his neck' उत्कंधरः; उन्मुखः &c.; 'r. ing both his arms' बाहू उद्यम्य. 2 उद्यम् c., उत्कृष्, उच्छ्रि, पदवृद्धिं कृ 8 U, प्रतिपत्तिं प्राप् c., उत्कृष्टपदे नियुज् 7 A, 10. 3 (Doubt, anger, &c.) उत्पद् c., जन् c., प्रभुद् c., उत्था c.; *See* **Cause. 4** वृध् c., *See* **Increase**; (building) निर्मा 3 A, 2 P, रच् 10; (tax) ग्रह् 9 U; *See* **Levy**; 'to r. one's voice' उच्चैः-तारस्वरेण-वद् 1 P; 'r. a cry' उत्क्रुश् 1 P, उद्-घुष् 10: 'r. dust' रजः उद्धूय, उद्-धू 5, 9 U, 6 P; 'r. a siege' अवरोधं त्यज् 1 P or मुच् 6 P. **-ed,** *a.* उत्थापित, उच्छ्रित, उन्नत, उन्नमित, उद्यत, उत्थित, उद्धृत; उत्पन्न, जात, जनित; oft. by उत्, उन्नत, उच्छ्रित in comp.; 'having the arms r.' उद्बाहुः &c. **-ing,** *s.* उत्थापनं, उन्नयनं, उन्नति *f.*, उत्क्षेपः, &c.

Raisin, *s.* शुष्कद्राक्षा.

Rake, *s.* विटः, लंपटः, व्यसनिन् *m.*, खंडितवृत्तः; *See* **Libertine. 2** दंतच्छुरिका-कर्तरिका **-v. t.** समाहृ 1 P, संग्रह् 9 P, सं-चि 5 U. **2** पुन-र्जीव् c.; उज्जीव् c. **-v. i.** व्यभिचर्. लंपटवत् आचर् 1 P, भोगासक्त्या आयुः क्षप् c. **-ish,** *a.* व्यसनिन्, लंपट, भोगासक्त, विषयसुखनिरत.

Rally, *v. i.* एकत्र-सं-भू 1 P, संमिल् 6 P, व्यूहीभू; *See* **Assemble. 2** (Fig.) सुस्थ-*a.* भू; प्रकृतिं आ-पद् 4 A, प्रकृतौ स्था 1 P, समुत्था, बलं लभ् 1 A. **-v. t.** एकत्र आनी or समाहृ 1 P, पुनः व्यूह् 1 U or क्रमेण विन्यस् 4 U or विरच् 10. **2 Jest,** q. v.

Ram, *s.* मेषः, उरभ्रः, उरणः, अविः, एडकः, मेढ्रः, ऊर्णायुः, वृष्णिः, हुडुः, लोमशः; 'a flock of r. s' औरभ्रं. **2** (Sign) मेषः, मेषराशिः. **-v. t.** बलात्-अतिबलेन् प्र-नि-विश् c. or प्रणुद् c., or संपीड् 10 'R.-rod', 'battering-r.' चूर्णप्रणोदनी यष्टिः.

Ramble, *v. i.* परि-अट् 1 P, परिभ्रम् 1, 4 P; विहृ 1 P, इतस्ततः चर् 1 P or भ्रम्; 'r. ing from the subject' अप्रस्तुतालापः. **-s.** परिभ्रमणं, पर्यटनं, विहारः, विहरणं. **-er,** *s.* पर्यटनशीलः, पथिकः, भ्रमणकारिन्.

Ramify, *v. i.* शाखाप्रतिशाखारूपेण विस्तॄ pass., उपशाखारूपेण विभिद् pass. **-v. t.** बहुशाखीकृ 8 U. **-ied,** *a.* शाखिन्, बहुशाखामय (यी *f.*), शाखाप्रतिशाखारूपेण विस्तीर्ण. **-ication,** *s.* प्र-प्रति-शाखा, बहुलउप-शाखा.

Rammer, *a.* मुद्गरः, घनः, अयोघनः.

Rammish, *a.* उग्र-तीक्ष्ण-गंध.

Ramous, *a.* शाखिन्, शाखाबहुल.

Ramp, *v. i.* कु 1 A, वल्ग् 1 P. **-s.** कुति *f.*, प्लुतं, वल्गितं; *See* **Leap. -Rampant,** *a.* अनियंत्रित, निरवग्रह, निर्बंध, उच्छृंखल. **2** अतिरिक्त, उद्रिक्त, उत्सिक्त, अतिमर्याद. **3** पश्चात्पादयोः स्थित. **-Rampancy,** *s.* अनियंत्रणा, अतिरेकः, उत्सेकः, अतिक्रमः, उत्क्रमः.

Rampart, *s.* प्राकारः, वप्रः-प्रं, वरणः. सालः; *See* **Fence.**

Rancid, *a.* उग्र or तीक्ष्ण-रस or गंध, विरस, पूतिगंधि.

Rancour, *s.* अभिद्रोहः, विद्वेषः, अतिद्वेषः-द्रोहः, अतिमात्सर्यं; *See* **Malice. -ous,** *a.* अभिद्रुग्ध, विद्वेषिन्, अति-दीर्घ-द्वेषिन्-द्रोहिन्, द्रोह-मत्सर-बुद्धि. **2** विषाक्त, विषपूर्ण, वैशसिक. **-ously,** *adv.* सद्वेषं, अतिद्रोहेण.

Random, *a.* आकस्मिक-यादृच्छिक-(की *f.*), अनियत, अचिंतित, संधानहीन, दैवायत्त, अतर्कितोपनत, सहसा उत्पन्न; 'at r.' अकस्मात्, यदृच्छया, निःसंधानं, अविचार्य, सहसा, असंचर्य, अनियतं, उच्छृंखलं; अव्यवस्थया, अक्रमेण; 'talk at r.' अक्रमेण जल्प् or वद् 1 P, (जल्पतोऽक्रमेण U. 1); 'oh! how he lies at r. carelessly diffused on the ground' हा हा कथं अवनीपृष्ठे निरुत्साहनिःसहं विपर्यस्तः (U. 3).

Randy, *a. See* **Disorderly.**

Range, *s.* राजिः, श्रेणिः-णी, माला, पंक्तिः, ततिः, आवलिः-ली, आलिः-ली, वीथिः-थी, (all *f.*). **2** गणः, वर्गः, वर्णः. **3** परिभ्रमणं, पर्यटनं. **4** सोपानं, आरोहणं. **5** विषयः, पथिन् *m.*, गोचरः in comp.; 'beyond the r. of sight' चक्षुर्विषयं-नयनगोचरं अतीत्य or अतीत; 'within the r. of hearing.' श्रुतिपथे-विषये-गोचरे; 'beyond the r.' अविषये, अविषय-विषयातीत-*a.*; 'r. of an arrow' शरपातः, बाणविषयः. **-v. i.** परिभ्रम् 1, 4 P, विचर् 1 P, विहृ 1 P (for diversion); 'r. about' इतस्ततो भ्रम्, पर्यट् 1 P. **2** स्था 1 P, वृत् 1 A; *See* **Be. -v. t.** विन्यस् 4 U, क्रमेण रच् 10, व्यूह् 1 U. **-er,** *s.* लुब्धकः, व्याधः. **2** वनग्राहिन् *m.*, वनपालः.

Rank, *s.* श्रेणि-णी *f.*, पंक्ति *f.*, राजि *f.*; *See* **Range, Line. 2** (Of an army) व्यूहः, वृंदं, सैन्यपंक्तिः-विन्यासः. **3** वर्गः, वर्णः, गणः. **4** पदं, स्थानं, आस्पदं, वृत्ति *f.*, स्थिति *f.* **5** प्रतिष्ठा, मानः, गौरवं, उत्कर्षः, उन्नति *f.*, प्रतिपत्ति *f.* प्राधान्यं, उच्च or परम-पदं, or पदवी, कुलोत्कर्षः, आभिजात्यं; 'a man of high r.' प्रतिपत्तिमत्, अभिजात, कुलीन, उच्चपदभाज् **-v. i.** समान-तुल्य-*a.* वृत् 1 A or स्था 1 P; पंक्तिक्रमेण स्था. **-v. t.** पंक्तिक्रमेण न्यस् 4 U or रच् 10, वर्गक्रमेण रच्; oft. ex. by वर्गे-पक्षे-स्था c. or गण्-कृत् 10, (कुटिपातमचुपकारपक्षे स्थापयंति Ka. 108); 'fit to be r. ed first' धुरि प्रतिष्ठापयितव्य or कीर्त-

नीय. 2 तुल्य-सम-*a.* मन् 4 A. -*a.* प्रभूत, प्रचुर, विपुल, अतिस्फीत, अतिरिक्त, उद्रिक्त. 2 उग्रगंध, पूतिगंधि, तीक्ष्णगंध. -**ness,** *s.* उद्रेकः, अतिस्फीति-वृद्धि- *f.*, अतिरेकः, प्रचुर-वृद्धिः. 2 उग्रता, तीक्ष्णता.

Rankle, *v.i.* उद्दीप् 4 A; उग्रतर-तीक्ष्णतर- *a.* भू 1 P; oft. ex. by शल्यं; 'those words r. in my heart' तद्वचो मम हृदये शल्यं जातं, शल्यमिव हृदये प्रस्तुतं; 'I r. in his eyes' अक्षिगतोऽहं तस्य. 2 अंतः पूय् 1 A or पूतीभू; 'the wound r. ed' स प्रहारः करालतां गतः (P. IV. 3).

Ransack, *v. t.* लुंट्-ठ् 1 P, 10; *See* **Plunder.** 2 निपुणं-सूक्ष्मं-अन्विष् 4 P or मृग् 10 A.

Ransom, *s.* निष्क्रयः; उद्धारः, निस्तारः, मुक्ति *f.*, मोक्षः; निस्तार-परिक्रय-मूल्यं. -*v. t.* मूल्यं-धनं-दत्वा मुच् c. or उद्धृ 1 P or निस्तृ c., निष्क्री 9 U, परिक्री 9 A. -**er,** *s.* निस्तारकः, निष्क्रेतृ *m.*

Rant, *s.* निरर्थक-निरर्गल-प्रलापः, शब्दमात्रं वाक्यं. -*v. i.* उच्चैः स्वरेण प्रलप् 1 P, शब्द-पांडित्यं कृ 8 U. -**er,** *s.* प्रलापिन् *m.*

Rap, *v. t.* तीव्रं प्रहृ 1 P or तड् 10 or अभिहन् 2 P. 2 अप-,हृ 1 P; ग्रह् 9 U, चित्तं-मनः-आकृष् 1 P or ग्रह. -*s.* तीव्र-प्रहारः-आघातः

Rapacious, *a.* अति-,लुब्धक, अपहारिन्, अपहरणशील, ग्रसनबुद्धि, सर्वहारिन्-ग्राहिन्, साहसिक (की *f.*). -**ly,** *adv.* प्रसह्य, प्रसभं, बलात्; अपहारबुद्ध्या, अतिलोभेन. -**ness,-Rapacity,** *s.* साहसिकता, आततायित्वं, अपहारशीलता, अपहरणबुद्धि *f.* 2 लुब्धता, अतिलोभः.

Rape, *s.* अप-,हरणं. 2 दूषणं, बलात्कारेण-बलात्-रतं-संभोगः; हठसंभोगः, आधर्षः-र्षणं, बलात्कारः, स्त्रीसंग्रहः; 'to commit r.' बलात्कारेण रम् 1 A or अभिगम् 1 P or संगम् 1 A, आधृष् c.

Rapid, *a.* शीघ्र, द्रुत, क्षिप्र, लघु.-**ity,-ness,** *s.* त्वरा, वेगः, तरस् *n.*; द्रुतता. -**ly,** *adv.* शीघ्रं, सत्वरं, द्रुतं; *See* **Quick,-ly** &c. -**Rapids,** *s.* वेगवत् स्रोतस् *n.*

Rapier, *s.* छुरिका, कर्तरिका, क्षुद्रकृपाणः.

Rapine, *s. See* **Plunder, Pillage.**

Rapt, *a.* हर्षोन्मत्त; परमहृष्ट, अत्यानंदित; (for 'wrapt') पर, लीन, निमग्न in comp. -**Rapture,** *s.* हर्षोन्मादः, आनंदातिरेकः, हर्षावेशः, अत्यंतहर्षः, प्रहर्षः, उन्मादः. -**ed,** *a.* हर्षोन्मत्त, उन्मत्त. -**ous,** *a.* उन्मत्त, परमहर्षद, मोहन; 'r. joy' परमानंदः. -**ously.** *adv.* सोन्मादं, परमहर्षेण; *See* **Ecstasy.**

Rare, *a.* विरल, दुर्लभ, दुष्प्राप, अप्राप्य, असुलभ; 'of r. occurrence' विरल, विरलवृत्त. 2 अपूर्व, अदृष्टपूर्व, परम, अत्युत्तम, अतुल्य, अत्युत्कृष्ट. 3 विरल, सूक्ष्म, अघन. -**ly,** *adv.* विरलं, क्वचित्, कृच्छ्रेण, कथमपि, कष्टेन, दुर pr.; oft. ex. by (*a.*); 'r. to be found' दुष्प्राप, दुर्लभ; 'r. to be seen' दुर्लभदर्शन. -**ness,** *s.* विरलता, दुष्प्रापता, दुर्लभत्वं. 2 अपूर्वता, अत्युत्तमता. 3 सूक्ष्मता. -**Rarity,** *s.* अपूर्वं वस्तु, चमत्कारः, कौतुकं, दुर्लभवस्तु. 2 **Rareness,** q. v. -**Rarefy,** *v. i.* सूक्ष्मी-तनू-विरली-भू 1 P. -*v. t.* तनूकृ 8 U, विरलीकृ.

Rascal, *s.* धूर्तः, दुर्जनः, जाल्मः, शठः, कितवः, दुरात्मन् *m.*, दुर्वृत्तः, खलः, पापात्मा, निंद्यचरितः, अधम-जघन्य-वृत्ति. -**ity,** *s.* धूर्तता, दौर्जन्यं, दौरात्म्यं, कैतवं, शाठ्यं, खलता, पापवृत्ति *f.*, अधम-नीच-वर्तनं. -**ly,** *a. See* (*s.*).

Rase, *v. t.* प्रमृज् 2 P or c., विलुप् c.; घृष् 1 P, उल्लिख् 6 P. 2 भूमिसात्कृ 8 U; *See* **Raze, Erase.** -**ure,** *s.* प्रमार्जनं, विलोपनं.

Rash, *a.* क्षिप्र-अविमृश्य-असमीक्ष्य-कारिन्, अविवेकिन्, अपरिणामदर्शिन्, साहसिन्, साहसिक (की *f.*), अदूरदर्शिन्, असावधान. 2 (Of acts) असमीक्ष्य &c. कृत; अविमृष्ट, सरभस, साहसिक, अविचार-असमीक्षा-पूर्व; better ex. by 'r.-ly.' -*s.* **Eruption, Pimple,** q.v. -**ly,** *adv.* असमीक्ष्य, अविमृश्य, सहसा, अविवेकेन, अविचार्य, अनालोच्य, अनवेक्षा-अविवेक-पूर्वं, सरभसं, क्षिप्रं, उत्तापेन, सावेगं.-**ness,** *s.* असमीक्ष्य-अविमृश्य-कारिता, साहसं, अविवेकः, अविचारः, असमीक्षा, अनवेक्षा, रभसः, आवेगः, उत्तापः.

Rasher, *s.* (वल्लूर) खंडः, छेदः.

Rasp, *s.* सं-,घर्षणी. -*v. t.* घर्षण्या घृष् 1 P.

Rat, *s.* आखुः, मूष(षि)कः, बिलेशयः, उंदुरुः, खनिकः; 'I smell a r.' किमप्यनिष्टं- अशुभं-आशंकते मे मनः. -*v. i.* कार्यात् अन्यपक्षं अवलंब् 1 A or आश्रि 1 U.

Ratan, *s.* वेतसः, वेणुः, वेत्रः-त्रं, वानीरः, वंजुलः; 'crackling r.' कीचकः.

Rate, *s.* मूल्यं, अर्घः, मूल्य-अर्घ-प्रमाणं, वस्नः, अवक्रयः. 2 मानं, प्र-परि°. 3 वेगः, गति *f.*, गतिमानं-प्रमाणं. 4 नियत-निरूपित-मूल्यं-वेतनं. 5 करः, शुल्कं, बलिः; 'at any r.' येन केन प्रकारेण, तावत्; 'market-r.' आपणिकः; अर्घबलाबलं. -*v. t.* अर्घ-मूल्यं-निर्णी 1 P or सं-स्था c., (स्थापयति) or निरूप् 10 or सं-ख्या c. 2 प्रमाणं निरूप्; oft. ex. by गण् 10,

मन् 4 A.; *See* **Consider. 3** निंद् 1 P, उपालभ् 1 A; *See* **Reproach.**

Rather, *adv*. Ex. by वरं with न च-न पुनः; for 'than'; *See* **Prefer;** 'I would r. die than be disgraced' वरं मृत्युर्न पुनरपमानः; 'I had r. not go there' वरं तत्र न गत एव, यदि न गच्छेयं तर्हि वरं-श्रेयः-स्यात्. **2** ईषत्, किंचित्, किमपि, किंचिदिव; 'r. less' ईषदून, किंचिन्न्यून.

Ratify, *v. t.* स्थिरीकृ 8 U, दृढीकृ, सत्याकृ, द्रढयति-सत्यापयति-(D), संस्तंभ् 9 P or c. प्रमाणीकृ. **-ier,** *s.* सत्यापकः, संस्तंभकः. **-ication,** *s.* स्थिरी-दृढी-करणं, संस्तंभनं, सत्यापनं, सत्यंकारः.

Ratio, *s.* संबंधः, प्रमाणं.

Ratiocinate, *v. i.* युक्तिपूर्वं-सहेतुकं-उपपद् c. or विचर् c. or वितर्क् 10; *See* **Argue.** **-ion,** *s.* वितर्कः, विचारः, युक्तिवादः.

Ration, *s.* अन्नपरिमाणं, आहारांशः, निरूपितान्नभागः.

Rational, *a.* विचारवत्, सचेतन, सचेतस्, विवेकिन्, सज्ञान, व्युत्पत्तिमत, व्युत्पन्न, प्रतिबोधवत्, चिच्छक्ति- ज्ञानशक्ति-संपन्न. **2** युक्त, उपपन्न, सयुक्तिक, न्याय्य, यथोचित, यथायोग्य, न्यायानुरूप, युक्तिसिद्ध, उपपत्तिमत्, न्यायानुसारिन्. **-ism,** *s.* हेतु-कारण-वादः, हैतुकत्वं. **-ist,** *s.* हेतु-न्याय-वादिन् *m.*, हैतुकः **-ity,-ness,** *s.* ज्ञानशक्ति *f.*, चिच्छक्तिः, ज्ञानं, अव-प्रति-बोधः, चेतनत्वं, तर्क-विचार-शक्तिः. **2** युक्तता, न्याय्यता, उपपत्ति *f.* **-ly,** *adv.* न्यायतः, युक्तिपूर्वं, न्यायानुसारेण, तर्क-विवेक-द्वारेण. **-Rationale,** *s.* उपपत्तिः.

Rattle, *v. i.* क्वण्-ध्वन्-स्वन्-रण् 1 P, शिंज् 2 A, वि-रु 2 P, झणझणायते (D.); (as a wheel) संक्रीड् 1 P, (संक्रीडति चक्रं S. K.). **2** प्रजल्प् 1 P, प्रलप् 1 P. **-v.** *t.* Causal of roots above. **-ing,** *s.* क्वणनं, शिंजितं, ध्वनिः, क्वणितं, वि-,रावः, झणझणायितं; संक्रीडितं. **2** प्रलपितं, प्रजल्पनं. **3** (Instrument) शिंजिनी, क्वणनी.

Rancous, *a.* परुष (स्वन).

Ravage, *v. t.* वि-उप-प्लु 1 A, उप-द्रु 1 P, प्र-सं-बाध् 1 A, अव-मृद् 9 P, उच्छिद् 7 P, विनश् c., उद्ध्वंस् c. **-s.** वि-उप-प्लवः, संबाधा, उपद्रवः, अवमर्दः, उच्छेदः, विनाशः, उद्ध्वंसः. **-er,** *s.* उपप्लवकारिन् *m.*, प्र-संबाधकः, अवमर्दकः, उच्छेदकः.

Rave, *v. i.* (भ्रमात्-उन्मत्तवत्) प्रलप् 1 P, प्रजल्प् 1 P, बुद्धिभ्रमेण वद् 1 P. **2** उन्मद् 4 P, नष्टचेतन-बुद्धिभ्रष्ट-*a.* भू 1 P. **-ing** *s.* वि-भ्रम-प्रलापः; चित्तविप्लवः-विभ्रमः, चैतन्यनाशः. **-ingly,** *adv.* उन्मत्तवत्, भ्रांतवत्, भ्रांतचेतसा, बुद्धिभ्रमेण.

Ravel, *v. t.* संग्रंथ् 9 P, संश्लिष् c., जटिलीकृ 8 U; *See* **Entangle. 2** विश्लिष् c., उद्-ग्रंथ्. **-ing,** *s.* विश्लिष्टतंतुः.

Raven, *s.* द्रोणकाकः, काकोलः. **-v.** गृध् 4 P, अतिलोभेन भक्ष् 10 or ग्रस् 1 A. **-ous,** *a.* घस्मर, अतिक्षुधार्त-क्षुधातुर, अतिलोलुप, आमिषलोलुप, अतिबुभुक्षु. **-ously,** *adv.* अतिघस्मरवत्, अतिलोलुपतया.

Ravine, *s.* कंदरः, दरीभृः, दरी, द्रोणी.

Ravish, *v. t.* प्रसह्य-बलात्कारेण-अभिगम् 1 P or भुज् 7 A or रम् 1 A, आ-प्र-धृष् c., दुष् c. (दूषयति), परा-परि-मृश् 6 P; *See* **Rape. 2** बलाद् अपहृ 1 P or नी 1 P. **3** (चित्तं) हृ, आकृष् 1 P, मुह् c., वि-लुभ् c., अत्यंतं-परमं-आनंद् c. or हृष् c.; *See* **Attract.** **-er,** *s.* आ-,धर्षकः, हठदूषकः, अपहर्तृ *m.* **-ing,** *s.* धर्षणं, बलसंभोगः, संग्रहः; *See* **Rape,-a.** हारिन्, मोहिन्, चित्ताकर्षिन्; हारिणा गीतरागेण (S. 1) 'by the r. melody of song'. **-ment,** *s.* अपहरणं, धर्षणं, दूषणं, &c. **2** हर्षोन्मादः, चित्तमोदः, मनोहरणं

Raw, *a.* आम, अपक्व, असिद्ध, असंस्कृत. **2** (Fruit) आम, अपक्व, अपरिणत, अकठोर, अप्रौढ. **3** (Mind) अपरिणत, अपरिपक्व, अपक्व; (person) अपरिणत-अकठोर-अपक्व-मति-बुद्धि; अदृष्टकर्मन्; not 'mature' q. v. **4** निश्चर्मन, त्वग्रहित. **5** आर्द्रशीतल. **6** जलामिश्रित, असंसृष्ट; 'r. flesh' क्रव्यं; आमामिषं; 'smell of r. flesh' विस्रं, आमगंधः; 'r. fruit' शलाटु *m. f. n.* **-ness,** *s.* अपाकः, आमता, अपरिणामः, अपरिपाकः; अपक्वबुद्धित्वं, मत्यपरिपाकः &c.

Ray, *s.* किरणः, करः, रश्मिः, अंशुः, उस्रः, पादः, मयूखः, मरीचिः, दीधितिः, गभस्तिः, धामन् *n.*, घृणिः, भानुः, अभीशुः-षुः; 'a pencil of r. s' अंशुजालं

Raze, *v. t.* उच्छिद् 7 P, अवसद् c., निपत् c., ध्वंस् c., विनश् c., उन्मूल् 10, उद्धृ 1 P; *See* **Erase,** also, 'r. to the ground' भूमिसात्कृ 8 U. **-ure,** *s.* उच्छेदः, विनाशः, विध्वंसः.

Razor, *s.* क्षुरः; 'r.-case' क्षुरभांडं; 'r.-strop' क्षुरतेजनी.

Re, as a prefix of verbs, ex. by पुनर् or प्रति; 're-consider' पुनः विचर् c.; 're-fill' पुनः पूर् 10, &c.

Reach, *v. t.* आप् 5 P, आ-समा-सद् c., उपा-आ-गम् 1 P or या 2 P, प्रति-प्र-पद् 4 A. *See* **Arrive. 2** अधिगम्, अश् 5 A, विद् 6 U, लभ् 1 A; *See* **Get. 3** (Hand)

प्र-सृ c., दृ 3 U, उच्छ्रि 1 U. 4 (Extend to) व्याप्, या, गम्; प्रसृ 1 P, विस्तृ-वितन्-pass.'; oft. ex. by पर्यंत, प्रमाण, in comp.; (in height) मात्र (त्री *f.*), दघ्न (घ्नी *f.*), द्वयस (सी *f.*); वृत्तांतेन श्रवणविषयप्रापिणा (R. xiv. 87) 'by the account r. ing (her) ears'; इदं प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव (Ka. 136) 'must have probably r. ed the ears of' &c. **-s.** गोचरः, विषयः, पथिन् *m.* **2** प्रसरः, पर्यंतः, प्रमाणं; 'the utmost r.' पारः; 'within the r. of' गम्य, ग्राह्य, लभ्य, विषय in comp.; धीगम्य, हस्तप्राप्य, प्रांशुलभ्य, &c.; 'beyond the r. of' अविषय, अतीत, अतिग, विषयातीत, अगोचर, अग्राह्य, अगम्य in comp.; अति pr.; बोधातीत, नयनागोचर, बोधविषय, अतिमानुष, &c. **-ing,** *a.* गामिन्, प्रापिन्, ग in comp.; better by (*v.*).

React, *v. i.* प्रति-कृ 8 U, प्रतिहन् 2 P, प्रत्याहन्. **-ion,** *s.* प्रतिक्रिया, प्रतिकारः; प्रतिघातः, प्रत्याघातः.

Read, *v.* पठ् 1 P, वच् c.; अधि-इ 2 A, अधिगम् 1 P; 'r. out' निर्वच् c., श्रु c.; 'r. to oneself' अनुवच् c.; 'r. through' अशेषतः पठ्, पारं गम् or दृश् 1 P, साद्यंतं पठ्, तॄ 1 P; 'he who has r. through the Vedas' श्रुतिपारदृश्वन् *m.* वेदपारंगतः; 'well-r.' अधीतिन्, (अधीती चतुर्ष्वाम्नायेषु D. K. ii. 5), स्वधीत, विद्यासंपन्न; *See* **Learned. -er,** *s.* वाचकः, पठितृ *m.*, अध्येता, अधीयानः, अध्ययन-पठन-कृत् *m.* **-ing,** *s.* पाठः, पठनं, अध्ययनं, अधिगमनं, वाचनं, अनुवाचनं, श्रावणं; 'this is a various r.' ति वा पाठः, पाठांतरमेतत्, पाठभेदोऽयं; r. through' पारायणं, अशेषपठनं; 'suspension of r.' अनध्यायः, अनध्ययनं.

Ready, *a* सज्ज, सिद्ध, उपक्लृप्त, सज्जीभूत-कृत, आयोजित, उपस्थित; सन्नद्ध; उप-परिकल्पित; 'to get r.' सज्जीकृ 8 U, उप-परि-क्लृप् c., उप-स्था c., (सबाणासनं त्वमुपस्थापय S. 2), सन्नह् 4 P or c.; *See* **Prepare;** 'to be r.' सज्जीभू; (food) सिद्ध, संस्कृत, निष्पन्न. **2** (Of persons) उद्यत, सिद्ध, सज्ज, सन्नद्ध, उद्युक्त, उन्मुख, अभिमुख; oft. by desid.; कूलं पिपतिषति 'is r. to drop down'; 'r. to go' गंतुमुद्यत, गमनोद्यत, गमनोन्मुख; 'stands r. to burst forth' भेदोन्मुखं तिष्ठति (V. 2.). **3** प्रत्युत्पन्न, तीक्ष्ण, कुशाग्र, सूक्ष्म, समयोपयुक्त, कालोचित. 4 शीघ्र, त्वरित, द्रुत, अविलंबित, क्षिप्र; कुशल, निपुण, दक्ष, पटु, लघु. **5** सुकर, सुगम, सुख, अनायासिन् **6** उत्सुक, इच्छु, सकाम, oft. ex. by मनः or काम with inf.; 'r. at hand' उपस्थित, हस्तगत, निकटवर्तिन्; 'having r. wit,' 'r.-witted' प्रत्युत्पन्नमति-धी-बुद्धि, विदग्ध. **-ily,** *adv.* कामं, कामतः, सकामं, इच्छापूर्वं, सोत्साहं, सोत्सुकं. **2** झटिति, शीघ्रं, सपदि, अचिरात्, आशु, अविलंबितं; *See* **Quickly. 3** सुखेन, अनायासेन, सुखं, अयत्नेन, अक्लेशेन, सुख in comp. **-iness,** *s.* सिद्धता, सज्जता, सिद्धि *f.* **2** सकामत्वं, इच्छा, औत्सुक्यं, उत्साहः. अविलंबः, शीघ्रता, तीक्ष्णता, सूक्ष्मता, प्रत्युत्पन्नता; दक्षता, &c.

Real, *a.* सत्य, अवितथ, वास्तविक-तात्त्विक (की *f.*), अकृत्रिम, परमार्थ, यथार्थ, तथ्य, अकल्पित, अकपट, अन्वर्थ. **2** (Property) स्थावर; 'to take to be r.' परमार्थेन ग्रह् 9 U; *See* **Earnest. -ity,** *s.* सत्यता, याथार्थ्यं, सत्यं, तथ्यं, तत्त्वं; 'un-r.' मिथ्यात्वं, असारता-त्वं, निःसारता; 'a r.' सत्यं, तत्त्वं, वस्तु *n.*, 'in r.' वस्तुतः, तत्त्वतः, परमार्थतः. **-ly,** *adv.* वस्तुतः, परमार्थतः, तत्त्वतः, यथार्थं, सत्यमेव, नूनं खलु; 'r. speaking' वस्तुवृत्तेन, परमार्थदृष्ट्या, तत्त्वतः, वस्तुतः. **-Realize,** *v. t.* साध् c.; परि-,पूर् 10, संपद् c.; *See* **Get. 2** प्रत्यक्षीकृ 8 U, सत्याकृ, प्रत्यक्षं अनुभू 1 P. **-ation,** *s.* साधनं, सिद्धि *f.*, निष्पत्ति *f.*, संपादनं, पूरणं, प्रत्यक्षीकरणं; 'r. of an object' कृतार्थता, इष्टसिद्धिः.

Realm, *s.* राष्ट्रं, विषयः, राज्यं; *See* **Kingdom. 2** प्र-,देशः, लोकः, भुवनं; 'r. s below the earth' अधोलोकः, पाताललोकः, अधोभुवनं.

Re-animate, *v. t.* पुनर्-जीव् c. **2** *See* **Refresh.**

Reap, *v. t.* (Corn) लू 9 U, छिद् 7 P, अव-कृत् 6 P, दो 4 P; छित्वा संग्रह् 9 P or सं-चि 5 U. **2** लभ् 1 A, आप् 5 P, भुज् 7A भज् 1 A, अनुभू 1 P, आ-स्वाद् 1 A; स्वकर्मफलभाग् भवतु (Mn. 1) 'let him r. the fruit of his own deeds'; 'as you sow, so you r.' यथा बीजं तथांकुरः. **-er,** *s.* लवितृ *m.*, लवकः, शस्यच्छिद्, शस्यसंग्राहिन्, संचयिन् *m.* **-ing,** *s.* लवनं, छेदनं, संग्रहः, संचयः; 'r-hook' लवित्रं, दात्रं, शस्यकर्तनी.

Rear, *s.* पृष्ठं, पार्ष्णिः, पृष्ठभागः-देशः; 'in the r.' पृष्ठतः, पश्चात्; 'we having fallen in the r.', अस्मास्ववहीनेषु (S. 2). **2** (Of an army) पृष्ठं, पार्ष्णिः, प्रत्यासा(स)रः, सैन्यपृष्ठं, परि-प्रति-ग्रहः, पतद्ग्रहः; 'one who attacks the r.' पार्ष्णिग्राहः; 'r.-guard' पार्ष्णित्रं. **-v.** *t.* उत्-स्था c. (उत्थापयति), उन्नी 1 P, उच्छ्रि 1 U, उद्यम् 1 A,

उन्नम् c.(उन्नमयति); *See* **Raise. 2** परि-सं-वृध् c.,परि-,पुष् 1, 4, 9 P, or c., वि-नी 1P, प्रति-परि-पा c. (पालयति), संभृ 3 U; *See* **Nourish. -ing,** *s.* उत्थापनं, उच्छ्रयः उन्नमनं, **2** पोषणं, भरणं, संवर्धनं, पालनं, विनयः.

Reason, *s.* (The faculty) मति-बुद्धि-व्युत्पत्ति *f.*, विवेकः,प्रज्ञा, विचारणाशक्ति *f.*, ज्ञानं, चिच्छक्ति., तर्क-अनुमान-शक्तिः; *See* **Intellect. 2** उपपत्ति *f.*, युक्ति *f.*, युक्तता, न्यायः,न्याय्यता, सामंजस्यं, याथार्थ्यं,हेतुः. **3** हेतुः, कारणं, निमित्तं, प्रयोजनं, (gen. with loc.); 'for what r.' किन्निमित्तं,कुतः, केन हेतुना,कस्य हेतोः,किमर्थं; 'for this r.' अतः, अनेन हेतुना, अस्मात्कारणात्; 'by reason of' ex. by abl. or instr.; हेतुना, कारणात्, अर्थे; 'for some r.' केनापि कारणेन. **-v.** *i.* वि-,तर्क् 10, ऊह् 1 A, अनु-मा 3 A, 2 P, युक्तिवादेन साध् c. or प्रति-पद् c.; विचर् c.; *See* **Argue,** 'r. ing faculty' विवेकः, धीशक्ति *f.*, विचारः. **-able,** *a.* **Rational,** q. v. **2** युक्त, न्याय्य, उचित, योग्य, उपपन्न, यथार्थ, न्याय-युक्ति-सिद्ध, यथान्याय; *See* **Just** also; 'to be r.' घट् 1 A, उपपद् 4 A, युज् pass. **3** परि-,मित, नियत, अनतिमहत्, नातिगुरु, मर्यादानतिक्रांत. **-ableness,** *s.* न्याय्यता, औचित्यं, युक्ति *f.*, उपपत्तिः, याथार्थ्यं, युक्तता; परिमितता, अनतिक्रमः, &c. **-ably,** *adv.* न्यायतः, युक्तिपूर्वं, सोपपत्तिकं, युक्तितः, यथान्यायं, यथोचितं, न्यायानुसारेण. **2** परिमितं, नियतं. **-er,** *s.* तार्किकः,तर्किन् *m.*,नैयायिकः, हेतुवादिन् *m.*, ऊहिन् *m.*, विचारकः, न्यायविद् *m.* **-ing,** *s.* वि-,तर्कः, विचारः, ऊहः-हनं, अध्याहारः, ऊहापोहः, न्यायः, अनुमानं; 'art of r.' तर्कशास्त्र-विद्या. **-less,** *a.* निर्बुद्धि, ज्ञानहीन. **2** अहेतुक, निष्कारण, [अनिमित्त.

Rebate, *v. t. See* **Blunt.**

Rebel, *s.* राजद्रोहिन् *m.*, राजापथ्यकारी, राजद्रुह् *m.*, राजप्रतिरोधी. **-v.** *i.* (राज्ञे) द्रुह् 4 P, अभिद्रुह् (with acc.); व्युत्था 1 A, प्रतियुध् 4 A, राजशासनं लंघ् 1 A, 10 or अतिक्रम् 1 U; 4 P. **-lion,** *s.* प्रकृतिकोपः,राजाभिद्रोहः, प्रजा or प्रकृति-क्षोभः or प्रकोपः,आज्ञा or शासन-अतिक्रमः or उल्लंघनं. **-lious,** *a.* राजद्रुह्, राजापथ्यकारिन्, राजाभिद्रोहिन्, &c.; *See* **Mutiny,-eer,** &c.

Rebound, *v. t.* उत्पत् 1 P, (पातितोपि कराघातैरुत्पतत्येव कंदुकः); उत्प्लु 1 A, प्रतिहन् pass. **-s.** उत्पतनं, प्रतिघातः.

Rebuff, *v. t.* प्रति-परा-हन् 2 P; पराभू 1 P, पराजि 1 A. **2** प्रत्यादिश् 6 P, निराकृ 8 U. **-s.** प्रतिघातः; पराभवः; पराजयः; प्रत्यादेशः; *See* **Repulse.**

Rebuke, *v. t.* निंद् 1 P, उपालभ् 1 A, आक्रुश् 1 P, गर्ह् 1, 10 A, निर्-,भर्त्स् 10 A. **-s.** निंदा, उपालंभः, निर्भर्त्सना, आक्रोशः; वाग्दंडः; *See* **Censure.**

Rebut, *v. t. See* **Refute, Repel.**

Recalcitrant, *a. See* **Refractory** under **Refract.**

Recall, *v. t.* प्रत्याह्वे 1 P, नि-प्रत्या-वृत् c., प्रत्यानी 1 P, प्रत्यादा 3 A. **2** (To mind) स्मृ 1 P, अनुचिंत् 10. **3** वि-लुप् 6 P or c., निवृत् c., प्रत्यानी, खंड् 10, निरस् 4 U, प्रत्यादिश् 6 P. **-s.** प्रत्याह्वानं, निवर्तनं, प्रत्यानयनं, प्रत्यादानं.

Recant, *v. t.* प्रत्या-ख्या 2 P, प्रत्यादिश् 6 P, खंड् 10, विलुप् c. **-ation,** *s.* प्रत्याख्यानं, प्रत्यादेशः, खंडनं, विलोपः, विपरीतवादः.

Recapitulate, *v. t.* संक्षेपतः कथ् 10 or वर्ण् 10, विषयसारं वर्ण्, भाषणसारं अनुवद् 1 P. **-ion,** *s.* संक्षेपतः वर्णनं, संक्षेपेण अनुवादः; (of past events) सिंहावलोकनं.

Recede, *v. i.* अपसृ 1 P, अपा-परा-नि-वृत् 1 A, अपसृप् 1 P, अपक्रम् 1 U, 4 P, अपगम् 1 P, अप-या-इ 2 P. **-ing,** *s.* अपसरणं, अपक्रमणं, अपयानं, &c.

Receive, *v. t.* आ-दा 3 A, प्रति-इष् 6 P, ग्रह् 9 U, प्रति-परि-°, प्रति-आ-पद् 4 A, स्वीकृ 8 U, अंगीकृ. **2** आप् 5 P, अधिगम् 1 P, लभ् 1 A; *See* **Get. 3** प्रविश् c.; *See* **Admit. 4** (A guest) प्रत्युद्-गम्-व्रज् 1 P, प्रत्युद्-इ-या 2 P, सं-मन् c., सं-भू c., सत्कृ, आ-दृ 6 A, स्वागतं वद् 1 P or व्याहृ 1 P. **5** आ-धा 3 U, ग्रह्, आ-दा, धृ 1 P, 10. **-ed,** *a.* आदत्त, आत्त, गृहीत, लब्ध, सत्कृत, संभावित, &c. **2** लोकप्रसिद्ध, अभिमत, प्रचलित, अभ्युपेत; 'r. practice' लोकाचारः, प्रचलितो व्यवहारः; 'r doctrine' आम्नायः, संप्रदायः. **-er,-Recipient,** *s.* प्रतिग्राहकः, परि-प्रति-ग्राहिन्, ग्रहीतृ, आदातृ all *m.* प्रतीच्छकः. **2** आशयः, आधारः, भाजनं, नि-आधानं. **-Receipt,** *s.* आदानं, ग्रहणं, प्राप्ति *f.* **2** आयः, लाभः, उदयः, फलं, आगमः, आदायः. **3** स्वीकारपत्रं, अभ्युपगमलेखः, प्रतिग्रहपत्रं-लेखः; 'or the creditor shall give a r. in his own hand' धनी वोपगतं दद्यात् (धनं) स्वहस्तपरिचिह्नितं (Y. ii. 93). **4** (Recipe) योगः, कल्पः, संस्कारलेखः. **-Receptacle,** *s.* आधारः,आ-नि-धानं, भाजनं,आशयः, पात्रं, निधिः, आश्रयः, आस्पदं, पदं; 'r. of bile' पित्ताशयः; आमाशयः, &c. **-Reception,** *s.* परि-प्रति-ग्रहः, आदानं, ग्रहणं, स्वी-अंगी-कारः, प्रवेशः-शनं. **2** संभावना, उपचारः, प्रत्युद्गमः. सत्कारः, संमानः, आदरः.

Recent, *a.* नव, अभिनव, नूतन, प्रत्यग्र, अचिर, अप्राचीन, अदीर्घकालीन. **-ly,** *adv.* *See* **Lately.**

Receptacle, } *See* under **Receive.**
Reception, }

Recess, *s.* विविक्तं स्थानं, निगूढस्थानं; कोणः, निभृत-गुप्त-स्थानं. **2** निर्वृति-विश्राम-स्थानं, आरामः. **3** विरामः, विश्रांति *f.*, क्षणः, कार्यत्यागः-निवृत्ति *f.*, विश्रामः, विश्रामकालः.

Recipe, *s.* *See* **Receipt, 4** under **Receive.**

Reciprocal, *a.* अन्योन्य, परस्पर, इतरेतर, व्यतिकर, मिथः, in comp.; oft. ex by व्यति pr.; *See* **Mutual.** **2** अन्योन्यानुगामिन्, परस्परानुवर्तिन्, अनुपूर्व. **-ly,** *adv.* परस्परं, इतरेतरं, मिथः. **-ness, -Reciprocity,** *s.* परस्परता, व्यतिकरः, व्यतिषंगः, व्यति(ती)हारः, विनिमयः, परि(री)वर्तः. **-Reciprocate,** *v. t.* परस्परं परिवृत् c., विनि-मे 1 A, व्यतिहृ 1 P; 'to r. assistance' प्रत्युपकृ 8 U; *See* **Exchange.** **-ion,** *s.* विनिमयः, व्यतिहारः, परिवर्तः.

Recite, *v. t.* पठ् 1 P, उदीर् c., उच्चर् c., अनुवद् 1 P, उदाहृ 1 P, उद्-गॄ 6 P. **2** वर्ण् 10, कथ् 10, आ-ख्या 2 P, व्याहृ; *See* **Tell.** **-al, -ation,** *s.* पठनं, उदाहारः, उद्गारः, उच्चारणं, अनुवादः. **2** कथनं, आख्यानं, वर्णनं. **-er,** *s.* पठकः, अनुवादकः, उच्चारकः, आख्यायकः.

Reck, *v. i.* गण् 10, अवेक्ष् 1 A; *See* **Care.** **-less,** *a.* प्रमत्त, अनवहित, असावधान, निरपे(वे)क्ष, साहसिन्. **-lessly,** *adv.* असावधानं, प्रमादेन, निःशंकं, अविचार्य. **-lessness,** *s.* प्रमादः, अनवधानं, साहसं, साहसशीलता.

Reckon, *v. t.* गण् 10, परि-सं-ख्या 2 P, कल् 10 (कलयति). **2** मन् 4 A, गण्, भू c. **-v. i.** वि-,तर्क् 10, अनु-मा 3 A, 2 P, ऊह् 1 A. **2** मन्, बुध् 1 P. *See* **Consider;** 'r. upon' आ-अव-लंब् 1 A, आश्रि 1 U, विश्वस् 2 P; 'r. with' देयं परिशुध् c. **-er,** *s.* गणकः, गणयितृ *m.* **-ing,** *s.* गणनं-ना, परि-, संख्यानं. **2** गणनापत्रं. **3** व्ययपत्रं. **4** मानं, गणना, मात्रा.

Reclaim, *v. t.* सत्पथे-सन्मार्गे-प्रवृत् c. or नी 1 P, or नियुज् 7 A, 10, दुर्मार्गात्-दुष्कर्मणः-नि-परा-वृत् c. or विरम् c., दुर्मार्गं त्यज् c. **2** कृषियोग्य-*a*, कृ 8 U. **3** पुनः लभ् 1 A or ग्रह् 9 U. **-Reclamation,** *s.* पापनिवृत्ति *f.*, दुर्मार्गपरावर्तनं; कुपथत्यागः. **2** पुनर्ग्रहणं; पुनर्लाभः-अवाप्ति *f.*

Recline, *v. i.* अव-आ-लंब् 1 A, समा-आश्रि 1 U. **2** शी 2 A, सं-उप-विश् 6 P, आस् 2 A; अध्यास्, अधि-शी (with acc.), निषद् 1 P, विश्रम् 4 P; *See* **Lie.** **-v. t.** नि-धा 3 U, उप-धा; *See* **Lean.** **-ing,** *a.* आलंबिन्, आश्रित, अवलंबित. **2** आ-अव-नम्र; शयान; संविष्ट, निषण्ण.

Recluse, *s.* परिव्राज् *m.*, संन्यासिन् *m.*, विविक्त-एकांत-वासिन्-सेविन् *m.*, वानप्रस्थः; 'female r.' परिव्राजिका. **-a.** विविक्त, निर्जन *See* **Lonely.** **-ness,** *s.* आरण्यकव्रतं, विविक्तसेवा, परिव्रजनं.

Recognize, *v. t.* प्रति-,अभि-ज्ञा 9 U, संविद् 2 A, परिच्छिद् 7 P, अनु-स्मृ 1 P, निश्चि 5 U, निर्णी 1 P; 'not properly r. ed' न तत्त्वतः परिच्छिन्नः. **2** स्वी-अंगी-कृ 8 U, प्रति-पद् 4 A, अभ्युपगम् 1 P, अभ्युप-इ 2 P, ग्रह् 9 U, प्रमाणीकृ. **-ance,** *s.* अंगीकारपत्रं, प्रातिभाव्यं, दर्शनप्रातिभाव्यं (r. bond); 'entered into a r. bond' दर्शनप्रतिभुवं ददौ. **-Recognition,** *s.* प्रति-,अभिज्ञा-ज्ञानं, परिच्छेदः. **2** अंगी-स्वी-कारः, प्रतिपत्ति *f.*, अभ्युपगमः.

Recoil, *v. i.* वि-परा-वृत् 1 A, व्यपवृत्; परापत् 1 P. **-s.** (अकस्मात्) परा-वि-वर्तः-र्तनं, परापतनं.

Recollect, *v. t.* स्मृ 1 P, अनु-सं-°, अनु-ध्यै 1 P, अनुचिंत् 10, अनुबुध् 4 A, 1 P. **2** (Oneself) धैर्यं अवष्टंभ् 9 P or अवलंब् 1 A; *See* **Courage;** 'he tries to r.' सुस्मूर्षते. **-ion,** *s.* स्मृति *f.*, स्मरणं, अनुचिंतनं, अनुबोधः; 'I am a sage having r of my former birth' अहं जातिस्मर मुनिः (Ka. 355).

Recommend, *v. t.* श्लाघ् 1 A, प्रशंस् 1 P; *See* **Praise.** **2** निक्षिप् 6 P, सं-,ऋ c. (अर्पयति); *See* **Entrust;** स्तुतिपूर्वकं निक्षिप् or उपन्यस् 4 U; or gen. ex. by स्तु 2 U, प्रशंस्; गुणान् प्रशंस्; 'I r. this boy to your care' अयं बालको भवतावेक्षणीय इति मे विनतिः; 'I shall, therefore, r. you to Damayanti तदहं विदधे तव स्तवं दमयंत्याः सविधे (N. II. 47); 'I beg to r. him to your kind notice' तस्मिन् कृपादृष्टिं पातयतु or तं स्निग्धदृष्ट्या पश्यतु भवान् इति मे प्रार्थना. **-ation,** *s.* गुणवर्णनं-प्रशंसा-कीर्तनं. **2** गुणवर्णनपत्रं, प्रशंसालेखः. **3** उपदेशः, अनुशासनं, प्रबोधनं. **4** अनुग्रह-प्रसाद-कारणं, आदरहेतुः 'a fair face is a good r.' आकृतिविशेषेष्वादरः पदं करोति (M. 1.). **-atory,** *a.* गुणश्लाघिन्, प्रशंसाकारिन्.

Recompense, *v. t.* शुध् c., निष्कृ 8 U, प्रतिकृ, प्रतिफलं-निष्कृतिं दा 3 U, निस्तॄ c.; (क्षतिं) पूर् 10 &c.; *See* **Compensate.** **2** मूल्यं दा; परितुष् c., सं-भू c.; *See* **Reward.** **-s.** पारितोषिकं, मूल्यं, प्रतिफलं; निष्कृति *f.*,

निस्तारः, शुद्धि *f.*, निर्यातनं, प्रतिक्रिया; पूरणं; क्षतिनिष्कृतिः- पूरणं.

Reconcile, *v. t.* सं-धा 3 U, सं-घट्ट् c. (घटयति), संमिल् c., द्वेषं-वैरं शम् c. (शमयति), सख्यं कृ 8 U; प्रसद् c., अनुनी 1 P, सांत्व् 10, सं-परि-तुष् c.; 'you are not yet r. ed' नाद्यापि प्रसादं गृह्णासि (M. 4.), न अनुनीयसे, प्रसन्ना न भवसि; 'easy to be r. ed' आशुसंधेय. 2 (Statement &c.) विसंवादं-विरोधं-अपनी 1 P or अपा-निरा-कृ, ऐक्यतां-एकवाक्यतां-संगतिं-कृ, समा-धा. 3 (Quarrels &c.) प्रशम् c., सं-धा, निराकृ. **-ed,** *a.* कृतसंधि, शांतवैर, प्रसादित, एकीकृत; 'to be r.' प्रसद् 1 P, मैत्र्यं गम् 1 P, प्रसादं ग्रह् 9 U, तोषं गम्, संमिल् 6 P. **-er,** *s.* संधातृ *m.*, समाधाता, संधिकृत् *m.* **-ment, -Reconciliation,** *s.* संधानं, संघटनं, प्रसादनं, संमेलनं, वैरशमनं, सख्यकरणं. 2 संधिः, सामन् *n.*, वैरशांति *f.*, पुनः सख्यं-मैत्री, सांत्वनं, अनुनयः, ऐक्यं. 3 समाधानं, संगति *f.*, एकवाक्यता, विरोधशमनं.

Recondite, *a.* गहन, नि-,गूढ, गूढार्थ, दुर्बोध, रहस्य, दुर्ज्ञेय, गहनार्थ.

Reconnoitre, *v. t.* निपुणं-सूक्ष्मं-परीक्ष् 1 A or निरूप् 10 or अनुसं-धा 3 U, गवेष् 10.

Record, *s.* लेख्यं, लेखः, पत्रं, पत्रकं, पट्टः, लेख्यप्रमाणं (evidence on r.). **-v.** *t.* आभि-, लिख् 6 P, लेख्ये-पत्रे-आरुह् c. or निविश् c. or ऋ c. (अर्पयति); *See* **Commit. -er,** *s.* लेखकः, लिपिकारः, कायस्थः (court-officer).

Recount, *v. t.* कथ् 10, आ-ख्या 2 P, वर्ण् 10, निविद् c., परि-,कृत् 10; *See* **Tell.**

Recoup, *v. t.* पूर् 10, प्रतिवि-धा 3 U पुनर् लभ् 1 A.

Recourse, *s.* आ-सं-उपा-श्रयः, आ-अव-लंबः, 2 शरणं, गति *f.*, (श्रीहरिर्मे गतिः); 'have r. to' श्रि 1 U, आ-उपा-समा-सं°, आ-स्था 1 P, आ-अव-लंब् 1 A; उपगम् 1 P.

Recover, *v. i.* आरोग्यं लभ् 1 A, रोगाद् विमुच् pass.; oft. by निर्, वि, गत in comp.; निर्विषः गौतमः (M. 4.) 'has r. ed from (the effects of) poison'; प्रकृतिं आपद् 4 A, सुस्थ-प्रकृतिस्थ-*a.* भू 1 P, रोगमुक्त-निरामय-*a.*भू; पूर्वस्थितिं आप् 5 P. 2 (From fainting) संज्ञां-चेतनां-लभ्; *See* below. **-v.** *t.* (पुनः) लभ्, प्राप्, विद् 6 U, प्रति-आ-पद्; प्रत्यवाप्, प्रत्यादा 3 A, प्रतिग्रह् 9 P, प्रत्याहृ 1 P, प्रत्युद्धृ 1 P; 'r. consciousness' संज्ञां-चेतनां-लभ् or प्राप्, प्रकृतिं-संज्ञां प्रति-आ-पद्, प्रकृतिस्थ-*a.* भू. 2 रोगं हृ or नश् c. or साध् c. or शम् c., नीरुज-स्वस्थ-*a.* कृ 8 U; *See* **Cure;** 'she r. ed him from poison' सा तं निर्विषं चकार. **-ed,** *a.* प्रतिलब्ध, प्रत्याहृत, पुनर्गृहीत, &c. 2 (From sickness) गत-नष्ट-शांत-रोग, नीरोग, निरामय, रोगमुक्त, स्वस्थ, प्रकृतिस्थ, उत्थित; oft. by मुक्त, गत, in comp.: 'r. from fever' ज्वरमुक्त; 'r. from swooning' नष्ट-गत-मोह; 'r. from poison' निर्विष, &c. 3 (From fainting) लब्ध-संज्ञ-चेतन, प्रकृतिमापन्न, प्रकृतिस्थ, चेतनापन्न. **-y,** *s.* पुनर्लाभः, पुनःप्राप्ति *f.*, पुनरादानं, प्रतिपत्ति *f.*, अधिगमनं, प्रत्युद्धारः. 2 स्वास्थ्यलाभः, आरोग्यप्राप्तिः, प्रकृतिलाभः, स्वास्थ्यं, निरामयत्वं, आरोग्यं, रोगमुक्ति *f.*

Recreant, *a.* धर्मभ्रष्ट, त्यक्त-लंघित-स्वधर्म, पतित. 2 कातर, भीरु, क्लीब; *See* **Coward.**

Recreate, *v. t.* (Oneself) विश्रम् 4 P, विहृ 1 P, रम् 1 A, क्रीड् 1 P. 2 आ-समा-प्रत्या-श्वस् c., आनंद् c., विनुद् c., रम् c. (रमयति), सं-परि-तुष् c.; *See* **Please, Refresh. -ion,** *s.* विश्रामः, विनोदः-दनं, विहारः, विहरणं, क्रीडा, कौतुकं, मनोरंजनं. **-ive,** *a.* सुखकर (री *f.*), मनोरंजन (नी *f.*), विनोदशील.

Recrement, *s. See* **Dross.**

Recriminate, *v.* प्रत्यभियुज् 7 A, 10, प्रत्यभिशंस् 1 P. **-ion,** *s.* प्रत्यभियोगः, प्रत्यारोपः; 'crimination and r.' परस्परदोषारोपः. **-ive,-ory,** *a.* प्रत्यभियोगिन्.

Recrudescence, *s.* पुनः प्रसर्पणं or उद्भवः. **-Recrudescent,** *a.* पुनः प्रसर्पिन्.

Recruit, *v. t.* शक्तिं वृध् c., प्रबलीकृ 8 U, आश्वस् c., आप्यै c., समा-प्रतिसमा-धा 3 U, सुस्थ-*a.* कृ; 'to r. the strength of' वाजीकृ. 2 नवसैनिकैः पूर् 10. **-v.** *i.* 'r. one's strength' बलं-सत्त्वं लभ् 1 A, स्वतेजः-वीर्यं प्राप् 5 P, सुस्थ-*a.* भू. **-s.** नूतन-नव-सैनिकः. **-ed,** *a.* लब्ध-प्राप्त-बल, वर्धित-सत्त्व, आप्यायित, प्रत्याश्वस्त. 2 नवसैनिकयुक्त-पूर्ण.

Rectangle, *s.* समकोणः. समचतुरस्रं. **-Rectangular,** *a.* समकोण, समचतुरस्र.

Rectify, *v. t.* समा-प्रतिसमा-धा 3 U, शुध् c. **-ication,** *s.* समाधानं, शोधनं.

Rectilineal, *a.* सरलरेखाविशिष्ट.

Rectitude, *s.* सारल्यं, आर्जवं, दाक्षिण्यं, न्याय्यता, शौचं, सत्यशीलता, सद्वर्तनं, सदाचारः; 'path of r.' सन्मार्गः, सुपथः, नीतिमार्गः-पथः; 'deviation from the path of r.' सत्पथत्यागः-भ्रंशः, उत्पथगमनं.

Rector, *s.* नायकः, अध्यक्षः. 2 ग्रामाचार्यः.

Recumbent, *a.* पार्श्वशय, अर्धकायेन शयान, कुक्षिशय, संविष्ट.

Recuperate, *v. t.* पुनर् लभ् 1 A.

Recur, *v. i.* प्रति-,आ-वृत् 1 A, पुनर् आगम् 1 P, or आपत् 1 P or सं-पद् 4 A or सं-भू 1 P or वृत् 1 A or उप-स्था 1 P; (to the mind) आविः-प्रादुः-भू, उद्-इ 2 P, स्फुर् 6 P, स्मृ pass. 2 शरणं गम् or प्रपद्. **-rence, -rency,** *s.* प्रत्यावृत्ति *f.*, पुनर्वर्तनं, पुनर्घटनं-आपातः-उपस्थानं-संभवः. 2 स्मरणं, स्फुरणं, प्रादुर्भावः, उदयः. **-rent, -ring,** *a.* आवर्तक, प्रत्यावर्तिन्.

Recusant, *a.* प्रतीप; *See* **Obstinate.**

Red, *a.* रक्त, लोहित, शोण (blood-r.), रक्त-लोहित-वर्ण,अरुण (dark r.), कषाय, शोणित; 'r.-hot' उत्तप्त, ज्वलत्, अभि-सं-तप्त, अग्निवर्ण; 'r.-lead' सिंदूरं; *See* under **Lead.** -*s.* (R. colour) रक्तवर्णः, अरुणिमन् *m.*, लोहितः, रक्तः. **-den,** *v. t.* लोहितीकृ 8 U, रक्तीकृ &c. -*v. i.* रक्तीभू 1 P, लोहितायते (D.). **-dish,** *a.* आरक्त-लोहित,ईषद्रक्त, &c. **-ness,** *s.* रक्तत्वं, लौहित्यं, रक्तिमा, अरुणिमा.

Redact, *v. t. See* **Edit. -ion,** *s. See* **Edition** (1)

Redeem, *v. t.* अव-हृ 1P, निष्क्री 9 U, परिक्री 9 A, धनं दत्त्वा मोक्ष् 10; मुच् c., मोक्ष्, वि-निर्-°, प्रत्या-दा 3 A, उप-नी 1 U; 'a pledge to be r. ed at a fixed time' कृतकालोपनेयः आधिः (V. M. 66). 2 परि-, त्रै 1 A, उद्-धृ 1 P, 10, निस्तॄ c. 3 पूर् 10, प्रतिकृ 8 U; *See* **Atone** for; 'he has this r.-ing virtue in him' अयं तस्य गुणोऽन्यान्दोषान् प्रमार्ष्टि-लोपयति **-er,** *s.* परिक्रेतृ *m.*,निष्क्रयिन् *m.* 2 त्रातृ *m.*,मोक्षकः, उद्धर्तृ *m.*, तारकः. **-Redemption,** *s.* निष्क्रयः, परिक्रयः-यणं. 2 परि-,त्राणं, उद्धारः, मोक्षः-क्षणं, मुक्ति *f.*, तारणं.

Redolent, *a.* सुगंधि, सपरिमल, सुरभि; *See* **Fragrant;** 'to make r.' वास् 10, सुरभीकृ 8 U.

Redouble, *v. t.* द्विगुणीकृ 8 U, पुनः पुनः कृ; अविरतोद्यमेन वृध् c. **-ed,** *a.* विवृद्ध, द्विगुणित, पुनः पुनः कृत.

Redoubt, *s,* दुर्गरचना.**-able,** *a.* भीम,विक्रांत, महापराक्रम, महाप्रताप, उरुविक्रम.

Redound, *v. i.* साध् c., आवह् 1 P, सं-पद् c. क्लृप् 1 A, सं-पद् 4 A (with dat.,) भू with dat.; 'will r.' to thy glory' तव यशसे भवेत्-कल्पेत &c. 2 अव-सो 4 P; परिणम् 1 P; oft. ex. by अंतः, परिणामः. 3 **Overflow,** q. v.

Redress, *v. t.* प्रतिकृ 8 U, निराकृ, समा-धा 3 U; उद्धृ 1 P, मुच् c. (persons); 'r. one's grievances' दुःखाद् मुच् c. or उद्धृ. -*s.* प्रति(ती)कारः, प्रतिक्रिया, समाधानं, उद्धारः.

Reduce, *v. t.* पूर्वस्थितिं नी 1 P, प्रत्यादिश् 6 P. 2 (Bring to a state) ex. by नी, गम् c., कृ 8 U or सात्कृ; 'r. to subjection' आत्मवशं नी, वशीकृ; 'r. to ashes' भस्मसात्कृ, भस्मीकृ, भस्मावशेषं नी or कृ; 'r. to a wretched state' दीनावस्थां नी; 'r. ed to a skeleton of bones' अस्थिमात्रावशिष्ट, कंकालशेष; 'who has r. ed kings to the state of tributaries' करदीकृतभूपालः. 3 न्यूनीकृ, अल्पीकृ, ह्रस् c., लघयति (D.), लघूकृ; वि-प्र-कृष् 1 P, (विप्रकर्षत्यलक्ष्मीं U. 5); अपकृष्; 'r. in price' अर्घतः पत् c.; 'r. the strength' बलं शिथिलीकृ or अपचि 5 U or क्षि 1, 5 P. 4 (Person) कृशीकृ, क्षीणीकृ, क्षै-क्षि c. (क्षपयति), शक्तिं अप-चि or अवसद् c. 5 वशीकृ, जि 1 P, पराजि 1 A, स्ववशं नी. 6 (In Math.) रूपं दा 3 U, रूपेण कथ् 10; 'r. to a system' व्यव-स्था c., क्रमेण विन्यस् 4 U or विरच् 10. **-ed,** *a.* पूर्वप्रवृत्त; कृत, भूत, गमित, आपन्न, गत; 'r. to misery' कृच्छ्रगत, कृच्छ्रापन्न, कष्टापन्न; 'r. to ashes' भस्मीकृत, भस्मीभूत. 2 वशीकृत, न्यूनीकृत;क्षीणबल &c.; 'you appear to be much r.' अतीव क्षामः-कृशगात्रः दृश्यसे; अपचितं गात्रं (S. 2) 'a body r. in bulk,' 'r. in strength' क्षीणबल, शिथिलबल, क्षीण, कृश. **-Reduction,** *s.* करणं, नयनं, गमनं, &c. 2 ह्रासः, अप-विप्रकर्षः, अपचयः, न्यूनीकरणं, न्यूनता, शैथिल्यं 3 पराजयः, वशीकरणं, पराभवः.

Redundant, *a.* अतिरिक्त, समधिक उद्रिक्त, उत्सिक्त, अत्यंत; व्यर्थ, पुनरुक्तभूत, अतिशय in comp. **-ly,** *adv.* सातिशयं, उद्रिक्तं. **-Redundancy,** *s.* आधिक्यं, अतिरेकः, उत्सेकः, उद्वृत्तः, पौनरुक्त्यं, व्यर्थता; *See* **Excess, -ive.**

Reduplicate, *v. t.* द्विगुणीकृ 8 U. 2 (In grammar) अभ्यस् 4 P (syllable); आम्रेडयति (D.) (word). **-ion,** *s.* अभ्यासः. आम्रेडितं, आमेडनं, द्विरुक्ति *f.*,

Reed, *s.* नडः-ला, धमनः, पोटगलः; वेतसः, वेत्रं, वेणुः, वंशः; 'r. for writing', 'r.-pen' कलमः. **-y,** *a.* नड्वल, नल-वेत्र-मय (यी *f.*), वेतसपूर्ण.

Reef, *s.* शिलासंघातः, शिलोच्चयः-श्रेणी, शैलसेतुः. -*v. t.* संहृ 1 P; *See* **Contract.**

Reek, *v. i.* बाष्पं उद्-गृ 6 P or उद्वम् c. or उद्वम् 1 P or उत्क्षिप् 6 P, बाष्पायते (D.). -*s.* बाष्पः, धूमिका. **-ing,-y.** *a.* बाष्पोद्गारिन्, बाष्पमय (यी *f.*).

Reel, *v. i.* प्र-,स्खल् 1 P, पार्श्वे पत् 1 P, सं-वि-चल् 1P.-*s.* स्खलनं,विचलनं. 2 आवापनं.

Refection, *s.* अल्प or लघु-आहारः or भोजनं, उपाहारः. **-Refectory,** *s.* उपाहारशाला.

Refer, *v. i.* उद्दिश् 6 P, अधिकृ 8 U, लक्षीकृ; *See* **Allude, Advert;** आश्रि 1 U, अपेक्ष् 1 A, संबंध-अनुषंज्-pass.; 'it does not r. to me' न मत्संबद्धं तत्; oft. **by** विषय, पर, in comp.. ब्रह्मविषयाणि वाक्यांतराणि (S. B. 114). 'r. ing to Brahman'; संदिह्यमानानि वाक्यानि ब्रह्मपरतया निर्णीतानि (S. B. 166) 'have been proved to r. to Brahman.' -*v. t.* Ex. by दृश् 1 P, निरूप् 10, प्रच्छ् 6 P, क्र c. (अर्पयति), प्रति-पद् c., निर्दिश् 6 P; 'I r. you to the sage about it' तद्विषये मुनिमेव पृच्छ; 'r. the word to the dictionary' कोशे तं शब्दं निरूपय; 'the matter must be r.-ed to the judge for opinion' अयमर्थः अभिप्रायार्थं प्राड्विवाकाय निवेदनीयः-प्रतिपादनीयः-निर्देष्टव्यः. 2 आरुह् c.; आसंज् c.; संबंध् 9 P. **-ee,** *s.* प्रमाणपुरुषः, मध्यस्थः, निर्णेतृ *m.* **-ence,** *s.* अर्पणं. निवेदनं, निर्देशः &c. 2 उद्देशः, संबंधः, अनुषंगः, अपेक्षा, आश्रयः, विषयः, संपर्कः, अन्वयः, अनुसंधानं; 'a r. is here made to a mythological story' अत्र पुरावृत्तकथा अनुसंधेया (Mallinatha on K. I. 21); oft. ex. by आलोकनं, आलोचनं; 'on a r. to the book again' पुनः पुस्तकं आलोक्य &c.; भवन्निर्दिष्टस्थलं पुनरालोच्य &c.; 'in or with r. to' अधिकृत्य, उद्दिश्य, आश्रित्य, अपेक्ष्य, अपेक्षया-संबंधेन-विषये in comp.

Refine, *v. t.* वि-,शुध् c., विमलीकृ 8 U, प्र-, मृज् 2 P. 2 संस्कृ,परिष्कृ, उपस्कृ, विनी 1U. -*v. i.* शुध् 4 P, विमली भू 1P. **-ed,** *a.* वि-, शुद्ध,शोधित,हृतमल; 'r. gold' प्रवृद्ध-संस्कार-शुद्धं-हेम. 2 संस्कृत, संस्कारवत्, परिष्कृत, प्रबुद्ध; विनीत, शिष्ट, सभ्य. 3 अति-,सूक्ष्म. **-ment,** *s.* शोधनं, वि-,शुद्धि *f.*, शुद्धता, प्रमार्जनं. 2 संस्कारः, परिष्कारः, शिष्टता, सौजन्यं, चित्तप्रबोधः, शुद्धिः; 'r. of manners' विनयः, आचारसौजन्यं, सभ्याचारत्वं; 'a man of r.' शिष्टाचारः, विनीतः. 3 अति-,सूक्ष्मता. **-er,** *s.* सं-,शोधकः, शोधयितृ *m.*, मलहारिन् *m.*

Refit, *v. t. See* **Repair.**

Reflect, *v. i.* चिंत् 10, ध्यै 1 P, विचर् c., विगण् 10, भू c., तर्क् 10, विमृश् 6P, आलोच्-पर्यालोच् 10. 2 (On) आ-अधि-क्षिप् 6 P, निंद् 1 P, अव-ज्ञा 9 U; *See* **Censure.** -*v. t.* प्रतिक्षिप्, परा-प्रत्यावृत् c., प्रतिबिंबयति (D.); 'a lake r. ing stars' ताराप्रतिबिंबं सरः; 'this action r. s great credit on you' इदं ते चरितं अतीव प्रशस्यं. **-ed,** *a.* प्रतिबिंबित, परावर्तित, संक्रांत, प्रतिफलित; 'to be r.' मुर्छ् 1 P, संक्रम् 1 U, 4 P, परावृत् 1 A, प्रतिफल् 1 P; हर्म्येषु मूर्च्छंति न चंद्रपादाः (R. XVI.18); मणिकुट्टिमसंक्रांतप्रतिबिंबतया (Ka.9.) **-ing,** *a.* परावर्तनकारिन्, परावर्तिन्. 2 चिंता-ध्यान-शील, विचारशील. **-ion,** *s.* चिंता, विचारः, विमर्शः, भावना, ध्यानं. 2 आ-अधि-क्षेपः, आक्षारणं. 3 परावर्तनं, प्रतिक्षेपः, संक्रांति *f.* 4 प्रतिबिंबः-बं, प्रतिच्छाया, प्रतिफलं; छाया, प्रतिमा, प्रतिमूर्ति *f.* -रूपं. **-or,** *s.* आदर्शः, दर्पणः-णं, प्रतिक्षेपकः, परावर्तकः. 2 विचारकः. **-Reflexible,** *a.* परावर्तनीय. **-Reflexive,** *a.* पूर्वसंबंधिन्; 'a r. verb' कर्मकर्तृवाच्यं. **-ly,** *adv.* कर्मकर्तरि.

Refluent, *a.* परावर्तिन्. **-Reflux, Refluence,** *s.* परावर्तः, प्रतिस्यंदः.

Reform, *v. t.* दोषं अपनी 1 P or खंड् 10 or अपाकृ 8 U or निवृत् c.; पापात् निवृत् c. or विरम् c.; दुर्मतिं नश् c., (of persons). 2 शुध् c., परि-वि-सं-°, समा-प्रतिसमा-धा 3 U, प्रतिकृ. 3 पुनः कृ of क्लृप् c. or वि-धा. -*v. i.* पापात् नि-परा-वृत् 1 A or विरम् 1 P, पापमार्गं त्यज् 1 P. -*s.*, **-ation,** *s.* पाप-दोष-निवृत्ति *f.*-त्यागः, दोषच्छेदः खंडनं-शोधनं-समाधानं; पापप्रतिकारः, संशोधनं, परिवर्तनं; (religious) धर्मपरिवर्तनं क्रांति *f.* **-atory,** *s.* शोधनालयः, **-ed,** *a.* निवृत्त or त्यक्त-पाप or दोष, विरत-हृत-दोष, संशोधित. **-er,** *s.* निवर्तकः, संशोधकः, दोष-पाप-च्छिद् *m.* 2 धर्मप्रवर्तकः.

Refract, *v. t.* परावृत् c., वक्रीकृ 8 U; 'to be r.-ed' वक्रीभू 1 P, परावृत् 1 A. **-ion,** *s.* वक्रीभवनं-करणं, परावर्तनं, वक्रीभावः. **-Refractory,** *a.* विप्रतीप, अविधेय, अविनेय, अवश्य, अनिवार्य, शासनलंघिन्; *See* **Perverse;** 'do not show a r. spirit towards thy husband' भर्तुः प्रतीपं मा स्म गमः (S. 4). 'to be r.' प्रतीपायते (D.). **-iness,** *s.* प्रतीपता, वक्रता, दुःशीलं, वक्रभावः, अविधेयता.

Refragable, *a.* छेद्य, खंडनीय, भेद्य.

Refrain, *v. t.* नि-सं-यम् 1 P, निग्रह् 9 P. निवृ 5 U or c, संहृ 1 P; *See* **Control.** -*v. i.* निवृत् 1 A, विरम् 1 P, (with abl.); परिहृ 1 P, वि-,सृज् 10, त्यज् 1 P; *See* **Abstain, Cease, Forbear.** -*s.* ध्रुवकः [अनुपदं.

Refrangible, *a.* परावर्तनीय.

Refresh, *v. t.* समा-प्रत्या-आ-श्वस् c., आनंद् c., जीव् c., आ-प्र-ह्लाद् c., सुखयति (D.).

2 नवीकृ 8 U, (एते वयं पुनर्नवीकृताः स्मः S. 5.): श्रमं अपहृ 1 P or छिद् 7 P or अपनी 1 P, विश्रम् c.; बलं-सत्त्वं वृध् c., आप्यै c. 3 निर्वा c. (वापयति), शीतलयति (D.), शीतलीकृ; *See* **Cool.** **-ed,** *a.* हृत or गत-क्लम or श्रम, विश्रांत, आप्यायित, आश्वासित, नवीकृत, छिन्नश्रम. **-ing,** *a.* आह्लादन (नी *f.*), क्लम-श्रम-विनोदिन्, आनंद-सुख-प्रद, श्रम-क्लम-च्छिद्, श्रमापह, क्लांतिहर. **-ment,** *s.* आह्लादनं, श्रम or क्लम-अपहारः or विनोदनं, आश्वासनं, श्रम-क्लांति-च्छेदः, विश्रांति *f.*, विश्रामः. 2 अभ्यवहारः, लघ्वाहारः, उपाहारः; 'morning r. प्रातराशः, कल्यवर्तः.

Refrigerate, *v. t.* तापं-दाहं-ह्व 1 P or नश् c. or छिद् 7 P, निर्वा c. (वापयति), शीतलीकृ 8 U; *See* **Cool.** **-ion,** *s.* ताप-दाह-च्छेदः, निर्वापणं. **-Refrigerant,** *a.* निर्वापक, ताप-दाह-हर. **-***s.* उष्णनिर्वापणं, तापशमनं.

Refuge, *s.* आश्रयः, संश्रयः, शरणं, गति *f.*; (person) शरण्यः, आश्रयभूतः, पालकः, रक्षकः, त्रातृ *m.* 2 उपायः, प्र-,युक्ति *f.*, गतिः, साधनं; 'giving r.' शरण्यः &c; 'take r. with' शरणं या 2 P or गम् 1 P or प्रपद् 4 A, उपा-आ-सं-श्रि 1 U, अवलंब् 1 A, शरणार्थं गम् &c: 'seeking r.' शरणार्थिन्: 'come for r.' शरणं प्रपन्नः, शरणागत; 'having only one r.' अनन्यगतिक. **-Refugee,** *s.* शरणं प्रपन्न, शरणागतः, शरणार्थिन् *m.* आश्रितः, अवलंबितः.

Refulgent, *a.* देदीप्यमान, विभ्राजमान, भास्वत्, उज्ज्वल, अतितेजस्विन्, प्रद्योतमान; *See* **Bright.** **-Refulgence,** *s.* अतिप्रभा-तेजस् *n.*, औज्ज्वल्यं.

Refund, *v. t.* प्रतिदा 3 U, प्रति-ऋ c. (अर्पयति.)

Refuse, *v. t.* प्रत्या-ख्या 2 P, नि-प्रति-षिध् 1 P, प्रत्याचक्ष् 2 A, निराकृ 8 U, प्रत्यादिश् 6 P, निर्-अप-अस् 4 U, वि-प्रति-हन् 2 P, न मंमन् 4 A or ग्रह् 9 U or अंगीकृ or प्रतीष् 6 P, अवधीर् 10: 'pray, do not r. my request' नार्हसि मे प्रणयं विहंतुं (R. II. 58). 2 (Followed by inf.) Ex. by a sentence with वच्, वद् &c. (Say, q. v.). **-***s.* उच्छिष्टं, अवशिष्टं, अवशेषः, शेषः-षं; असारः, मलं. **-***a.* उच्छिष्ट, असार, अवशिष्ट.

Refute, *v. t.* निराकृ 8 U, निरस् 4 U. प्रतिक्षिप् 6 P, खंड् 10, बाध् 1 A, अधरीकृ, प्रत्या-ख्या 2 P, प्रत्यादिश् 6 P, अपवद् 1 U, निर्धू 5, 9 U, 6 P. **-ation,** *s.* निरासः, निरसनं, खंडनं, निराकरणं, प्रतिक्षेपः, प्रत्याख्यानं.

Regain, *v. t.* पुनः लभ् 1 A or प्राप् 5 P, प्रतिपद् 4 P; *See* **Recover.**

Regal, *a.* राजकीय, राजार्ह, राजोचित.

Regale, *v. t.* संतृप् c., संतुष् c., आह्लाद् c., आनंद् c. 2 आश्वस् c., आप्यै c, संवृध् c.; *See* **Refresh,** 'r. oneself' उत्तमान्नेन संतुष् 4 P or संतृप् 4 P or आत्मानं संतुष् c., उत्सवं कृ 8 U.

Regalia, *s.* राजचिह्नानि-लक्षणानि-लिंगानि, राजोपचारः

Regard, *v. t.* आदृ 6 A, प्रति-अव-ईक्ष् 1 A, संमन् c. पूज् 10, नि-,सेव् 1 A. 2 ईक्ष्, दृश् 1 P, आ-अव-लोक् 1 A, 10, आ-,लक्ष् 10; *See* **Look.** 3 मन् 4 A, वि-,गण् 10. 4 अव-धा 3 U, अवेक्ष्, सावधान-*a.* भू, विगण्, आदृ. 5 सेव्, पा c.(पालयति), अनु-ष्ठा 1 P; *See* **Observe.** 6 उद्दिश् 6 P, अपेक्ष्; संबंध् 9 P. **-***s.* आदरः, संमानः, पूजा, अवेक्षा. 2 अवधानं, मनोयोगः, अवेक्षा. 3 दृष्टि *f.*, ईक्षणं; *See* **Look.** 4 स्नेहः, प्रणयः, अनुरागः, प्रीति *f.* 5 विचारः, अवेक्षा, अपेक्षा, अनुसंधानं, गणना, उद्देशः, संबंधः, अन्वयः; विषयः; 'having r. to the result' फलापेक्षया; 'with r. to' उद्दिश्य, अधिकृत्य, अंतरेण, अपेक्ष्य, (with acc.); अपेक्षया, विषये, गत-*a.* in comp.; 'a scandal with r. to Mālavikā' मालविकागतं कौलीनं (*M.* 3); भर्तृगता-विषया-चिंता &c. **-ful,** *a.* अवे (पे)क्षक, अवहित, सावधान, सापेक्ष. **-fully,** *adv.* सापेक्षं, सावधानं. **-ing,** *a.* सापेक्ष, संबंधिन्, गत-विषय- in comp.; *See* (*s.*). **-less,** *a.* निरपेक्ष, अनपेक्ष, उदासीन, विरक्त, अनुत्सुक, in comp. gen.; oft. by अनादृत्य, अनवेक्ष्य, अगणयित्वा. **-lessly,** *adv.* निरपेक्षं, उपेक्षया. **-lessness,** *s.* अनपेक्षा, उपेक्षा.

Regatta, *s.* नौकाक्रीडा.

Regenerate, *v. t.* पुनर् जन् c. (जनयति) or जीव् c. or उद्-धृ 1 P, 10, or उत्था c. (उत्थापयति). **-***a.*, **-ed,** *a.* पुनर्जात, पुनर्भव, पुनर्जन्मन्, पुनरुज्जीवित. **-ion,** *s.* पुनरुज्जीवनं, पुनरुत्पत्ति *f.*, पुनर्जन्मन् *n.*; उत्थापनं, उद्धारः.

Regent, *s.* पालः in comp.; शासकः, अधिपतिः, शास्तृ *m.* 'r.s of the eight quarters' अष्ट दिक्पालाः. 2 शून्यपालः; राजप्रतिनिधिः. **-Regency,** *s.* शासनं. 2 राजप्रतिनिधि-मंडलं.

Regicide, *s.* राजवधः-हत्या-हिंसा-घातः. 2 (Person) राजहन् *m.*, राजघातकः, राजघः.

Regime, *s.* *See* **Government.**

Regimen, *s.* अन्नपानविधिः, पथ्यापथ्यनियमः. 'one observing r.' पथ्याशिन्.

Regiment, *s.* सैन्यदलं-गुल्मं-गणः-व्यूहः;

Regimentals, *s.* सैनिकवेषः.

Region, *s.* प्र-,देशः, लोकः, भुवनं; विषयः, राष्ट्रं, चक्रं, मंडलं; (of the sky) दिश् *f.*, काष्ठा, आशा; *See* **Direction;** ' r. of the heart ' हृदयदेशः; नाडीचक्रं &c.

Register, *s.* लेख्यं, लेखः, पत्रिका, पंजिका; गणनापत्रं. **-v.** *t.* पत्रिकायां लिख् 6 P or निविश् c. **-Registrar,** *s* लेखकः, पंजिकाधिकृतः. **-Registry, Registration,** *s.* नामलिखनं, पत्रिकायां निवेशनं or आरोपणं 2 लिखनस्थानं.

Regnant, *a.* शासक, अधिकारिन्, राज्याधिकारिन्.

Regorge, *v. t.* उद्गम् 1 P, उद्-गॄ 6 P, निःसृ c.

Regress, *s.* प्रतीपगति *f*, परावर्तनं. **-v.** *i.* परावृत् 1 A, प्रत्यावृत्. **-ion,** *s.* प्रतीपगमनं, प्रत्यावर्तनं.

Regret, *v. t.* अनुशुच् 1 P, अनुतप् 4 A. *See* **Lament;** 'he died r. ed by all ' मृतः सर्वैरनुशोचितश्च; न वाप्यनुशोचिता (U. 3) ' nor was she (her absence) r. ed..' oft. ex. by दुःखित *a.* or दुःखं ' I r. I cannot go with you ' त्वया सह गंतुमसमर्थोस्मीति दुःखितोहं. **2** Repent, q. v. **-s.** दुःखं, अनुशोकः, अनुतापः, खेदः, मनस्तापः, उद्वेगः; *See* **Grief. -ful,** *a.* दुःखित, दुःखाकुल, अनुतप्त, अनुशोकार्त, उद्विग्न, खिन्न, सोत्कंठ.

Regular, *a.* नियत, नियमानुसारिन्, नैयमिक-वैधिक-(की *f.*), विध्यनुरूप, सूत्र-विधि-अनुसारिन्; ' not at r. hours ' अनियतवेलं (S. 2). **2** अनुपूर्व, अनुक्रमागत, यथाक्रम, क्रमानुगत, अनुलोम, क्रमानुसारिन्. **3** नियतकालिक (की *f.*) नियतवेल. **4** व्य-(व्या)वहारिक-आचारिक-(की *f.*), नित्य, यथामार्ग, यथारीति. **4** (Of persons) नियमानुसारिन्, नियमनिष्ठ-पर-शील, विधि-नियम-अनुवर्तिन्; व्यवस्थित, अत्यक्तक्रम, अव्यभिचारिन्, नियतवृत्ति. **-ity,** *s.* नियतत्वं, विध्यनुसारः, नियमः, सूत्रानुसारः, नैयमिकत्वं. **2** पर्यायः, अनुक्रमः, परिपाटि-टी *f.*, व्यवस्था, परंपरा, आनुपूर्व्यं, आनुलोम्यं; *See* **Order. 3** विधि-नियम-निष्ठा, नियमानुसारित्वं, विध्यनुवर्तनं, क्रमात्यागः, व्यवस्थिति *f.* विधि-नियम-परता. **4** (Of arrangement) विरचनं-ना, व्यूहः-हनं, विन्यासः. **-ly,** *adv.* यथा-अनु-क्रमं, अनुपूर्वशः, आनुपूर्व्येण, अनुलोमं, आनुलोम्येन, क्रमशः, क्रमेण, पर्यायेण. **2** यथाविधि, विधिवत्, विधितः, यथानियम, यथासूत्रं, विधिपूर्वकं, विधि-नियम-अनुसारेण. **3** नित्यं, अनुज्झितक्रमं, नियतक्रमेण, नियतवेलायां.

Regulate, *v. t.* सं-,वि-धा 3 U, परिकल्प् c., क्रमेण विन्यस् 4 U, विरच् 10, व्यव-स्था c. (स्थापयति). **2** वि-,नियम् 1 P, वि-धा; अनुशास् 2 P, नि-,यंत्र् 10: *See* **Rule, Control!;** ये द्वे कालं विधत्तः (*S.* I) ' who r. time. ' **3** यथाविधि व्यव-स्था c. or विधा, प्रमाणं निरूप् 10. **-ion,** *s.* विधानं, व्यवस्थापनं, यंत्रणं, शासनं, &c. **2** व्यवस्था वि-,नियमः, शासनं, विधिः, स्थिति *f.*, मर्यादा, क्रमः. **-or,** *s.* शासकः, संविधातृ *m.*, वि-,नियंता, शास्ता.

Rehearse, *v. t.* पठ् 1 P, अनुवद् 1 P. **2** कथ् 10, वर्ण् 10; *See* **Narrate. 3** प्रयोगात् पूर्वं अभिनी 1 P or नट् 10. **-al,** *s.* पठनं, अनुवादः; कथनं, आख्यानं, पूर्वप्रयोगः, पूर्वाभिनयः.

Reign, *v. i.* प्र-,शास् 2 P, राज्यं-महीं &c. शास् or अव् 1 P or भुज् 7 U. **2 Prevail,** q. v. **-s.** शासनं, राज्यपालनं, आधिपत्यं, अधिकारः; better by (*v.*) with loc. abs.; ' during Rama's r. ' रामे महीं शासति; ' after a r. of 12 years' द्वादशाब्दान् भुक्तक्षितौ तस्मिन्. **2** राज्यशासनकालः, राज्यकालः. **-ing,** *a.* राजपदारूढ, शासत्, राज्याधिकारिन्.

Reimburse, *v. t.* प्रतिदा 3 U, निष्कृ U, अपाकृ, पुर् 10, शुध् c.

Rein, *s.* अभीशुः-षुः, प्रग्रहः, रश्मिः; ' by drawing in the r. s' रश्मिसंयमनात् (S. 1). ' give the r. s to ' वशं या 2 P, आयत्तीभू 1 P, अधीन-*a.* भू; ' r. s of government ' राज्यसूत्राणि. **-v.** *t.* नि-सं-यम् 1 P, नि-प्र-ग्रह् 9 P; *See* **Control** 'r. in the horses' प्रगृह्यतां वाजिनः (*S.*1)

Reins, *s.* कटि-टी *f.*, कटि-श्रोणी-देशः. **2** वृक्का.

Reinforce, *v. t.* **Recruit.** q. v. **-ment,** *s.* सैन्यं, सेनासामग्री.

Reinstate, *v. t.* प्रति-ष्ठा c. (-ष्ठापयति), पुनः स्था c. or नियुज् 7 A, 10. **-ment,** *s.* प्रतिष्ठापनं, पुनर्नियोगः, पुनःस्थापनं.

Reiterate, *v. t.* **Repeat,** q. v. **2** पुनः पुनः कृ 8 U. **-ed,** *a.* पुनः पुनरुक्त; पौनःपुनिक (की *f.*). **-ion,** *s.* पुनर्वचनं, आम्रेडनं, पुनरुक्ति *f.*, पौनःपुन्यं.

Reject, *v. t.* अवधीर् 10, निराकृ 8 U, प्रत्या-ख्या 2 P, वि-हन् 2 P, प्रत्याचक्ष् 2 A; प्रत्यादिश् 6 P, निर्-अप-अस् 4 U, निर्धू 5, 9 U, प्रति-अप-क्षिप् 6 P, त्यज् 1 P; *See* **Refuse. -ion,** *s.* अवधीरणं-णा, निराकरणं, प्रत्यादेशः, प्रत्याख्यान, निरसनं.

Rejoice, *v. i.* प्री pass, मुद् 1 A, आनंद् 1 P, सं-परि-तुष् 4 P, हृष् 4 P, रम् 1 A, उल्लस् 1 P; *See* **Delight,** ' I r. to see you ' प्रीतोस्मि ते दर्शनात्, त्वद्दर्शनेन मुदितोस्मि; ' this is to be r. ed at ' एतदभिनंदनीयं (*S.* 5). **-c.** *t.* Causal of roots above. **-ing,** *a.* आनंदद, हर्षावह, हर्षकर

(रीf.). **2** प्रीयमाण, मुदित, हृष्ट. -*s.* आनंदः, हर्षः, प्रमोदः, उत्सवः.

Rejoin, *v.* *See* Answer. **-Rejoinder,** *s.* प्रतिवचनं, उत्तरं, प्रत्युक्ति *f.*

Rejuvenate, *v. t.* बलं-सत्वं-वृध् c., आ-प्यै c.

Relapse, *v. i.* पुनः पत् 1 P or आगम् 1 P or प्राप् 5 P; oft ex. by पुनः with other words; 'r -ed into a feverish state' ज्वरेण पुनरभ्यभूयत, पुनः ज्वरातुरो बभूव; 'r. ed into vice' पुनर्दुर्मार्गे गंतुं प्रचक्रमे, सत्पथात् भ्रष्टः, सन्मार्गं अत्यजत्; 'r. ed into his natural joviality' सहजामानंदवृत्तिं प्रत्यपद्यत. -*s.* ... प्रत्यावृत्ति *f.*, प्रत्यागमनं, पूर्वावस्थाप्राप्ति *f.*

Relate, *v. i.* (To) उद्दिश् 6 P, अपेक्ष् 1 A, अनुषंज्-संबंध् pass.: by deriv. in ईय, or विषय in comp.; 'r. ing to Sastras' शास्त्रीय, शास्त्रविषय; 'news r. ing to the king's murder' राजघातविषयकः-संबद्धः-वृत्तांतः; *See* **Refer.** -*v. t.* कथ् 10, आ-ख्या 2 P, वर्ण् 10, शंस् 1 P, चक्ष् 2 A, आ-नि-विद् c : *See* **Tell.** **-ed,** *a.* कथित, ख्यात, वर्णित, &c. **2** सं-अनु-बद्ध, अनुषक्त, अन्वित, संसक्त, संपृक्त, संबंधिन्, संपर्किन्, in comp. **3** संबंधिन्, सजाति, सजातीय, एक-स-गोत्र, सकुल्य, गोत्रज, एकशरीरान्वय. **-er,** *s.* आख्यायकः, कथयितृ *m.* **-ing,** *a.* (To) संबंधिन्, विषय in comp. *See* **Refer.** **-ion,** *s.* संबंधः, अन्वयः, संदर्भः, संसर्गः, संपर्कः, अनुषंगः, भावः; 'mutual r.' व्यतिषंगः, अन्योन्यसंबंधः, आकांक्षा (between a word and its meaning), 'intimate r.' समवाय-नित्य-संबंधः; 'the r. of the container and the thing contained' आधाराधेयभावः. **2** बंधुता, ज्ञातिभावः, शरीरसंबंधः, शरीरान्वयः, सजातित्वं, सगोत्रता, सपिंडता. **3** बंधुः, बांधवः, ज्ञातिः, गोत्रजः, सगोत्रजः, सकुल्यः, संबंधी, सपिंडः (to the 7th degree), समानोदकः (8th to 14th degree), सनाभिः, सोदर्यः, समानोदरः (by blood) 'r. s collectively' बांधवगणः-जनः- बंधु-ज्ञाति-वर्गः. **4** आ-उपा-ख्यानं, वर्णनं, कथनं. निरूपणं, कीर्तनं **-ionship,** *s.* बंधुता, सनाभिता, ज्ञातिभावः, संबंधः; 'near r.' प्रत्यासन्नता; 'distant r.' व्यवहितता. **-ive,** *s.* सगोत्रः, सकुल्यः, बांधवः, बंधुः, ज्ञातिः; *See* **Relation.** -*a.* सापेक्ष, अविविक्त, अन्यसापेक्ष, अकेवल; 'r. importance' तारतम्यं **2** अन्योन्यान्वित. **3** संबंधिन्, विषयक, in comp.: अनुविद्ध, अनुषक्त, संबद्ध, सान्वय, उद्दिष्ट. 4 संबंधवाचिन्. **-ively,** *adv.* अन्यापेक्षया, अन्यसापेक्षं. अपेक्ष्य; *See* **Comparative.**

Relax, *v. t.* शिथिलीकृ 8 U, शिथिलयति (D.), श्रथ्-श्रंथ् 1, 9 P., 10, वि-,स्रंस् c., विगल् c. **2** मुच् 6 P, or c., विसृज् 6 P. **3** शिथिलीकृ, प्र-शम् c. (शमयति), न्यूनीकृ, लघूकृ, मंदीकृ, (मंदीचकार मरणव्यवसायबुद्धिं K. iv. 45); 'r. ing their efforts' शिथिलितप्रयत्नाः. **4** उद्-ग्रंथ् 9 P, वि-सं-धा 3 U: 'r. the bowels' विरिच् 7 P or c.; *See* **Purge**; 'r. the mind' मनः विलुभ् c., or विश्रम् c. -*v. i.* शिथिलीभू 1 P, श्लथ् 1 P, श्रथ् 1 A, स्रंस् 1 A, शिथिलायते-मंदायते (D.). **2** प्र-उप-शम् 4 P, न्यूनी-भू. **-ation,** *s.* शैथिल्यं, विस्रंसः, प्रश्रथः, मुक्ति *f.* **2** प्र-उप-शमः-शांति *f.* न्यूनीभावः. **3** विनोदः, विश्रामः, उद्योगविरति *f.*-निवृत्ति *f.*- शैथिल्यं. **-ed,** *a.* शिथिलित, शिथिल, प्र-,श्लथ, मुक्त, स्रस्त, विगलित; 'having r. his hold' मुक्त or शिथिलित-ग्रहः or हस्तः.

Relay, *s.* विश्रामदायी जवाश्वगणः or सेवकगणः.

Release, *v. t.* मोक्ष् 10, मुच् 6 P or c., वि-निर्-°, उद्धृ 1 P, निस्तॄ c., विसृज् 6 P; *See* **Free.** -*s.* वि-मुक्ति *f.*, मोक्षः, मोचनं, उद्धारः, निस्तारः. **-er,** *s.* मोचकः, मोक्षकः, उद्धर्तृ *m.*

Relegate, *v. t.* वि-वस् c. **2** ऋ c. (अर्पयति).

Relent, *v. i.* करुणामृदु-करुणार्द्र-मृदुचित्त-*a.* भू 1 P: अनुकंप् 1 A, दयार्द्रीभू, करुणया द्रु 1 P: 'his heart r. ed' तस्य मनो मार्दवमभजत, कठिनतामजहात्; 'being appeased, he r. ed' सचानुनीतो मृदुतामगच्छत् (R. v. 54): किमपि सानुक्रोशः कृतः (S. 4) 'somewhat r. ed'. **-less,** *a.* निर्दय, निष्करुण, निरनुक्रोश, क्रूर, कठोर, कठिन-पाषाण-हृदय, निर्घृण; *See* **Cruel.** **-lessly,** *adv.* निर्दयं, निष्करुणं, कठोरं.

Relevant, *a.* प्रास्ताविक (की *f.*), प्रस्तुत, प्रस्तुतानुषंगिन्, प्रासंगिक (की *f.*), प्रस्तावसदृश (शी *f.*)-उचित-अनुरूप, प्रसंगोचित. **-ly,** *adv.* प्रस्तावसदृशं, प्रासंगिकं. **-Relevance,-cy,** *s.* प्रस्तावौचित्यं, प्रस्तावसंगति *f.*, प्रस्तुतानुसारः-अन्वयः, प्रकरणानुसारः, प्रास्ताविकत्वं.

Relic, *s.* अव-शिष्टं-शेषः-षं, शेषभागः; शव.-वं, मृतशरीरं.

Relict, *s.* *See* **Widow.**

Relieve, *v. t.* (persons) (दुःखात् &c.) मुच् 6 P or c, मोक्ष् 10, उद्धृ 1 P: दुःखं &c. अपनी 1 P or शम् c. (शमयति) or परिहृ **2** (Pain &c.) प्र-शम् c., परिहृ, दूरीकृ; लघयति (D.), विश्रम् c., लघूकृ; *See* **Alleviate,** 'I feel myself to be r. ed' समात्मा विशदः जातः (S. 4), निर्वृतोऽहं.

3 उपकृ, साहाय्यं दा 3 U, अनुग्रह् 9 P. 4 (Guard &c.) विश्रम् c., नियोगात् विश्रामं दा. -ed, a. उद्धृत, मुक्त, शांत, शमित &c.; 'r. of anxiety' वीतचिंत, निश्चित, निःशल्य (मनः); 'r. of pain' शांतदुःख. -Relief, s. (दुःखात्) मोचनं, मोक्षः, उद्धारः, शमनं, मुक्ति f., अपहरणं, अपनयनं, परिहारः. 2 सुखं, उप-प्र-शमः, निर्वापणं, चिंता-प्रशमः-शांति f. स्वास्थ्यं, निर्वृत्तिः, विश्रामः, निश्चितता; एकपदे एव दुःखविश्रामं ददाति (U. 6) 'gives r. to my sorrow'; कर्तव्यानि दुःखितैर्दुःखनिर्वापणानि (U. 3). 3 उपकारः, साहाय्यं; 'she brought her lovely limbs into r.' पुपोष लावण्यमयान् विशेषान् (K. 1. 25).

Religion, s. धर्मः. 2 Piety, q. v. -Religious, a. धर्म्य, धर्म-द्वेष- in comp.; 'r. rites' धर्मक्रियाः. 2 धर्मासक्त. पुण्यशील, धर्मचारिन्, व्रतिन्, धर्मनिष्ठ, धार्मिक (की f.). See Pious, -ly, adv. धार्मिकवत्, ईश्वरभक्त्या. -ness, s. धार्मिकत्वं, धर्मनिष्ठा, धर्मपरता.

Relinquish, v. t. त्यज् 1 P, उत्-वि-सृज् 6 P, हा 3 P, मुच् 6 P. -ment, s. त्यागः, उत्सर्गः, मोचनं; See Abandon,-ment.

Reliquary, s. अवशिष्टाधारः-भाजनं.

Relish, v. t. स्वाद् c., रस् 10, सुरसीकृ 8 U, स्वादूकृ. 2 आस्वाद् 1 A. 3 अभि-,रुच् 1 A, अभिनंद् 1 P; See Like, s. रसः, आ-,स्वादः-स्वादनं, रुचि f.: 'has lost r. for dates' पिंडखर्जूरैरुद्वेजित (S. 2). 2 अभि-,रुचिः, अभिलाषः, इच्छा. 3 अव-उप-दंशः.

Reluctant, a अनिच्छत्, विमनस्, अनिच्छु, असंतुष्ट, अकाम, निष्काम, वि-पराङ्-मुख, विमत. -ly, adv. बलात्, अनिच्छया, अकामं-मतः-मेन, by (a.), 'he went out r.' अनिच्छन्नपि निर्जगाम. -Reluctance, s. अनिच्छा, अकामः, असंतोषः, वैमनस्यं, विमुखता, अरुचि f.

Rely, v. i. (On) विश्वस् 2 P, प्रति-इ 2 P. विश्रंभ् 1 A: श्रद्धा 3 U 2 आ अव-लंब् 1 A, आ-सं-श्रि 1 U: oft. ex. by आयत्त, अधीन, तंत्र in comp.: 'I r. on you alone' भवानेव ममाश्रयः शरणं. -iance, s. विश्वासः, प्रत्ययः, विश्रंभः, श्रद्धा. 2 अवलंबः-बनं, आ-सं-श्रयः, शरणं. -ing, a. अवलंबिन्, आश्रित, विश्वासिन्, जातप्रत्यय.

Remain, v. i. अव-स्था 1 A, स्था 1 P, आस् 2 A, वृत् 1 A: See Continue. 2 नि-,वस् 1 P, स्था, अधि-वृत्. 3 शिष् pass., अव-परि-उत्°-, उद्-वृत; 'he r. ed only' in memory (his name only r. ed) स्मर्तव्यशेषं नीतः; 'r. ing after what is eaten' भुक्तावशिष्टं, भुक्तशेषं (अन्नं); 'those who r. ed alive' हतशेषाः. -ing, a. अव-,शिष्ट-शेष, उद्वृत्त; 'pass the r. months' शेषान्मासान्गमय; 'during the r. part of his life' आयुःशेषे. -Remains, s. अस्थ्यादिशेषः, अस्थीनि. -Remainder, s. अव-, शेषः-षं-शिष्टं,उद्वर्तः, शेषभागः; (in arithmetic) शेषं, अंतरं; (of men) ex. by अन्य, इतर; See Other; 'subtracting 4 from 10 the r. is 6' दशसु चतुर्भिर्विवर्जितेषु षड् शेषं or षड् अवशिष्यंते.

Remand, v. t. पुनः प्र-हि 5 P or आह्वे 1 P.

Remark, v. t. लक्ष् 10, अवेक्ष् 1 A, निरूप् 10. 2 अभि-धा 3 U, वच् 2 P, वद् 1 P: See Observe. -s. उक्ति f., वचनं, अभिधानं, वचस् n., भाषणं; (written) लिखितं, लेखः. 2 अवेक्षणं, निरूपणं. 3 चर्चा, अनुशासनं. -able, a. अपूर्व, अद्भुत, आश्चर्यभूत. 2 विख्यात, विश्रुत, अलौकिक (की f.), लोकोत्तर, प्रसिद्ध, विशिष्ट, उत्कृष्ट, स्मरणार्ह, विशेष in comp. -ably, adv. सातिशयं, विशेषेण, विशेषतः, अद्भुतं, विशिष्टप्रकारेण.

Remarried, a. पुनरूढ, पुनर्भू.

Remedy, v. t. प्रतिकृ 8 U, प्रतिवि-धा 3 U, प्रतिसमा-समा-धा; परिहृ 1 P: प्र-उप-शम् c. (शमयति), साध् c., कित् desid. (चिकित्सति-ते): उप-चर् 1 P. -s. औषधं; भेषजं, अगदः; See Medicine. 2 प्रतिक्रिया, प्रति-(ती)कारः, उपशमः, उपायः, उपचारः, प्रतिविधानं, उपक्रमः, चिकित्सा, प्रतिसमाधानं. -iable, a. प्रतिकार्य, प्रतिविधेय, चिकित्स्य, शक्यप्रतिकार, शक्योपचार. -ial, a. प्रतिकारक, प्रतिकारिन्, (s.) in comp.: 'a r. measure proves effective' प्रतिकारविधानं फलाय कल्पते (R. viii. 40.). -less, a. अप्रतिकार्य, अप्रतिविधेय, निरुपाय अप्रतिकार, दुरुपचार.

Remember, v. t. स्मृ 1 P, सं-अनु-,° (with gen. when regret is shown), अनुचिंत् 10, अनु-बुध् 1 P, 4 A. 2 (Keep in mind) स्मृ, हृदये-चित्ते नि उप-धा 3 U, मनसि कृ 8 U, अव-धृ 10: 'please, r. these words well' हृदि एनां (भारतीं) उपधातुमर्हसि (R. viii. 77); 'r. me to your brother' स्मर्तव्योऽहं तव भ्रातुः. -Remembrance, s स्मरणं, स्मृति f., अनुचिंतनं, अवधारणं-णा. 2 स्मारकं, स्मारणं, स्मरणवस्तु, अभिज्ञानं, 'r. of love' प्रीत्यभिज्ञानं. -er, s. स्मारकः, उद्बोधकः.

Remind, v. t. स्मृ c., अनु-सं-°, उद्-प्र-अनु-बुध् c.; 'this group of gallants, as if, r. s me to-day of Patala' पाताले मामद्य संस्मरयतीव भुजंगलोकः (Rat. 1), 'Oh

I am well r. ed' अये सम्यगनुबोधितोस्मि (S. 1). **-er,** *s.* उद्बोधकः, अनुबोधकः.

Reminiscence, *s.* स्मृति *f.*, स्मरणं; *See* **Memory.**

Remiss, *a.* अनवधान, असावधान, प्रमत्त, निरपेक्ष, उपेक्षक, मंदादर, शिथिलोद्यम; 'to be r.' प्रमद् 4 P (with abl.). **-ly,** *adv.* अनवधानेन, उपेक्षया, निरपेक्षं, प्रमादेन. **-ness,** *s.* अनवधानं, उपेक्षा, निरपे(पे)क्षा, प्रमादः, शैथिल्यं.

Remit, *v. t.* प्र-हि 5 P, प्रेष् c., प्रति-ऋ c. (अर्पयति); संचर् c., संक्रम् c. **2** शिथिलीकृ 8 U, मुच् 6 P, वि-उत्-सृज् 6 P, त्यज् 1 P, विरम् 1 P, निवृत् 1 A, (with abl.). **3** क्षम् 1 A, निवृत् c., मुच्, अवसृज्, त्यज्. **4** प्र-उप-शम् c., (शमयति), लघूकृ, न्यूनीकृ. **-v. i.** प्र-उप-शम् 4 P, शिथिलीभू 1 P, विरम्. **-tance,** *s.* प्रेषणं, संक्रामणं; प्रेषितधनसंख्या. **-tent,** *a.* संतत, अविसर्गिन्. **-ting,** *a.* विरत, विसर्गिन्, शिथिलित. **-Remission,** *s.* शैथिल्यं, प्र उप-शमः-शांति *f.*, विरामः. **2** मोचनं, मुक्ति *f.*, निस्तारः, उद्धारः. **3** मार्जनं, क्षमा, विच्छेदः, निवृत्ति *f.*, उत्सर्गः.

Remnant, *s.* अव-,शेषः-षं; *See* **Remainder.**

Remonstrate, *v. i.* (With) निवारणार्थं उपदिश् 6 P, निवारयितुं यत् 1 A, प्रत्यादिश् प्रत्या-ख्या 2 P; *See* **Dissuade.** **-Remonstrance,** *s.* प्रत्यादेशः, प्रबोधवचनं, निवारणोपदेशः, निवर्तनं.

Remorse, *s.* अनुतापः, अनुशयः, अनुशोकः, पश्चात्तापः. **-ful,** *a.* अनुतप्त, अनुशयार्त; *See* **Repentance,** &c. **-less,** *s.* कठिन, निर्दय; *See* **Cruel.**

Remote, *a.* दूर, दूरस्थ, दूरवर्तिन्, असंनिहित, विप्रकृष्ट; *See* **Distant. -ly,** *adv.* दूरं, विप्रकृष्टं; 'he is r. connected with me' स मम विप्रकृष्टः बधुः. **-ness,** *s.* विप्रकर्षः, असंनिकर्षः, दूरता.

Remount, *s.* अश्रांतः अश्वः. **-v. t.** अश्वं पुनर् आरुह् 1 P.

Remove, *v. t.* स्थानांतरं नी 1 P or गम् c., अप-सृ c., वि-, चल् c. **2** दूरीकृ 8 U, निर्वस् c., निष्कस् c., अप-निः-उत्-सृ c., बहिष्कृ; (from office) प्र-, भ्रंश् c., च्यु c.; *See* **Dismiss, Discharge.** (of things) अपनी, निनुद् c., अपहृ 1 P, अप-अव-कृष् 1 P. अप-अपा-नुद् 6 P or c.. अप-व्यप-ऊह् 1 U. निर्-अप-अस् 4 U, निराकृ, अपाकृ, उच्छिद् 7 P, वि-नश् c., प्रतिकृ, खंड् 10, नि-प्रति हन् 2 P, भंज् 7 P. निर्-अव-धू 5. 9 U. 6 P. **-v. i.** स्थानांतरं गम् 1 P or या-सृ-2 P: अपसृ 1 P, अपगम्-या. **-s.** पुरुषः (in geneology) 'separated by one r. from the creator' ब्रह्मरेकांतरं (द्वंद्वं) (S. 7). **2** पदं, पदवी, क्रमः. **3** अपगमः, अपसरणं, &c.: *See* below. **-al,** *s.* अपनयनं, उत्सारणं, दूरीकरणं, विचालनं, स्थानांतरीकरणं. **2** अपसरः-रणं, अपयानं, अपगमः-गमनं, स्थानांतरं, स्थलभेदः. **3** निरासः, निराकरणं, प्रभ्रंशनं, अप-परि-हारः-हरणं, उच्छेदः, विनाशः-शनं, अपनोदः, अपोहः, प्रतिघातः, प्रति(ती)कारः, खंडनं, भंगः &c. **-er,** *s.* अपनेतृ *m.*, अपहर्ता, नाशकः, उच्छेत्ता; gen. ex. by हारः, हारी, अपहः, हा, घ्नः, अंतकः in comp., also हृत, नुद् in comp.: 'r. of darkness' तमोनुत, तमोहृत, तमश्छिद् &c.

Remunerate, *v. t.* मूल्यं-वेतनं-प्रतिफलं दा 3 U; *See* **Recompense, Reward.** **-ion,** *s.* मूल्यं, वेतनं, प्रतिफलं, पारितोषिकं.

Renaissance, *s.* (विद्यायाः) पुनरुज्जीवनं.

Rencounter, *s.* संमर्दः, द्वंद्वं, संघट्टः, अभिघातः; *See* **Battle, Collision.**

Rend, *v. t.* दृ 9 P or c., भिद् 7 P, छिद् 7 P, व्यध् 4 P, विश् 9 P; वि-उद्-दल् c. (दलयति), खंड् 10: *See* **Tear,** 'heart-r. ing' हृदयस्पृश्, हृदिस्पृश्, हृदयमर्मच्छिद्. **-er,** *s.* विदारकः, भेदकः. **-ing,** *s.* विदारणं, भिदा, स्फुटनं, भेदः, भंगः. **-Rent,** *a.* विदीर्ण, स्फुटित, भिन्न &c. **-s.** छिद्रं, रंध्रं, भेदः, विदरः, स्फुटनं, भिदा, भंगः.

Render, *v. t.* प्रति-दा 3 U, प्रति-ऋ c. (अर्पयति), प्रति-पद् c., निर्यत् c. **2** दा, कृ 8 U, उपक्लृप् c. **3** जन् c, उत्पद् c., कृ; by the causal of roots. 'r. help' साहाय्यं कृ or दा; 'to r. pond' दृप् c.: 'r. unfriendly' विकृ c., &c. विरंज् c. **4** **Translate,** q. v.

Rendezvous, *s.* समागम-संकेत-स्थानं, संकेत गृहं-स्थलं.

Renegade, *s.* धर्मभ्रष्टः, पतितः, पाखंडः, स्वधर्म-स्वपक्ष-त्यागिन् *m.*

Renew, *v. t.* नवीकृ 8 U, प्रतिसमा-धा 3 U. उद्धृ 1 P. पूर्वावस्थां नी 1 P or प्राप् c. or गम् c. **2** पुनः कृ; gen. ex. by पुनः आरभ् 1 A with other words; 'r. s studies' पुनः अध्ययनं प्रारभते; 'they r. ed hostilities पुनः वैरं प्रारेभिरे. **-al** *s.* नवीकरणं, पूर्ववत्करणं, प्रतिसमाधानं, उद्धारः, पुनःकरणं, पुनः प्रारंभः.

Renounce, *v. t.* न स्वीकृ or अंगीकृ 8 U, प्रत्या-ख्या 2 P, प्रत्यादिश् 6 P, प्रत्याचक्ष् 2 A; *See* **Refuse. 2** त्यज् 1 P, अपास् 4 U, वि-उत्-सृज् 6 P, हा 3 P; *See* **Abandon,** 'to r. the world' संन्यस्, सर्वसंगं परित्यज्. **-Renunciation,** *s.* प्रत्यादेशः, प्रत्याख्यानं, परित्यागः, उत्सर्गः, परिहारः; 'r. of the world' संन्यासः, सर्वसंगपरित्यागः.

Renovate, *v. t.* नवीकृ 8 U, पुनः कृ. **-ion,** *s.* नवीनता, नूतनावस्था, उद्धारः, *See* **Refresh, Renew.**

Renown, *s.* कीर्ति *f.*, यशस् *n.*, प्र वि-ख्याति *f.*, विश्रुति *f.* **-ed,** *a.* प्र-वि-ख्यात, विश्रुत, प्रथित, लब्धकीर्ति, प्रसिद्ध, लब्धप्रतिष्ठ; *See* **Fame,-ous.**

Rent, *s.* करः, बलिः, राजस्वं. *-v. t.* भाटकेन दा 3 U: भद् *c.*, भाटकेन-मूल्यदानेन-ग्रह् 9 U or सेव् 1 A or भुज् 7 A. **-al,** *s.* 'r.-bill' करपत्रिका.

Reorganize, *v. t.* पुनर् वि-रच् 10 or घट् *c.*

Repair, *v. t.* नवीकृ 8 U, सं-धा 3 U प्रतिसमा-समा-धा, उद्धृ 1 P, पूर्ववत्कृ, पुनः स्वस्थीकृ, सुस्थित *a.* कृ. **2** (Loss &c.) पूर् 10, प्रमृज् 2 P, निष्कृ, शुध् *c.*, प्रतिकृ, सं-धा. *-v. i.* आश्रि 1 U, प्रपद् 4 A, गम्-व्रज् 1 P, शरणं प्रपद् or गम् or या 2 P or अभ्युप-इ 2 P. *-s.* प्रति-,समाधानं, संस्कारः,संधानं, उद्धारः, नवीकरणं, पूर्वावस्थाप्रापणं. **-Reparable,** *a.* पूरणीय; उद्धार्य, प्रतिसमाधेय; 'loss not r.' अपूरणीया हानिः. **-Reparation,** *s.* **Repair,** q. v. **2** क्षति or हानि-पूरणं or निष्कृति *f.*, शोधनं, प्रतिफलं.

Repartee, *s.* क्षिप्रोत्तरं, व्यंगोक्ति *f.*, भंगि-भाषणं, सरसोक्तिः.

Repast, *s.* भोजनं, अन्नं, आहारः, अशनं, अभ्युपहारः.

Repatriate, *v. t.* (निर्वासितं) स्वदेशं प्राप् *c.*

Repay, *v. t.* प्रतिदा 3 U, प्रति-ऋ *c.* (अर्पयति), निर्यत् 10, प्रति-पद् *c.*, निवृत् *c.*, प्रतिकृ 8 U. **2** प्रतिफलं-निष्कृतिं-दा, निष्कृ, अपाकृ, शुध् *c.*, अपवृज् 10, oft. by प्रति; 'r. kindness' प्रत्युपकृ; 'r. an injury' प्रत्यपकृ, वैरं साध् *c.* **-ment,** *s.* प्रतिदानं, प्रत्यर्पणं, निर्यातनं, शोधनं, शुद्धि *f.*, प्रतिफलं.

Repeal, *v. t.* खंड् 10, निरस् 4 U, वि-,लुप् *c.*, नि-परा-वृत् *c.*, उच्छिद् 7 P. *-s.* वि-, लोपः, निवर्तनं, खंडनं, निरसनं, प्रचारलोपः-भंगः. **-er,** *s.* निवर्तकः, विलोपकः.

Repeat, *v. t.* पुनः वद्-गद् 1 P, or उदीर् *c.* or व्याहृ 1 P, (Say, q. v.): अभ्यस् 4 U, (a letter) आम्रेडयति (D.). **2** आवृत् *c.*, पुनः-मुहुः-कृ 8 U or आचर् 1 P or अनु-ष्ठा 1 P. 'ten r. ed two times' द्विरावृत्ता दश, द्विदशाः. **3** पठ् 1 P, व्याहृ, अनुवद्, उद्गृ 6 P, आ-ख्या 2 P, कथ् 10, उदीर्. **-ed,** *a.* पुनरुक्त, पुनर्भणित, पुनः पुनः कृत, आवृत्त, आवर्तित; 'with r. exertions' पुनः पुनः कृतैः प्रयत्नैः; 'in r. birth, परिवर्तिनि जन्मनि, जन्मनि जन्मनि. **-edly,** *adv.* वारं वारं, भूयो भूयः, पुनः पुनः, मुहुर्मुहुः, अभीक्ष्णं, असकृत्, बहुशः, अनेकशः. **-Repetition,** *s.* पुनरुक्ति *f.*, पुनर्वादः, पुनर्वचनं-कथनं, पौनरुक्त्यं; 'made as a r.' पुनरुक्त, पुनरुक्ततां नीत; *See* **Superfluous. 2** पठनं, समभिव्याहारः, अनुवादः, अनुलापः. **3** आवृत्ति *f.*, आवर्तनं, पुनः विधानं-अनुष्ठानं-आवृत्तिः, पौनः-पुन्यं, अभ्यासः; आम्रेडितं, द्विरुक्तिः (of a word &c.).

Repel, *v. t.* अपास् 4 U, प्रति-ध्या-हन् 2 P, प्रतिसृ *c.*, निरस्, प्रतिक्षिप् 6 P, प्रतिवृ *c.*, अपानुद् 6 P, नि-परा-वृत् *c.*, प्रत्याविश् 6 P; *See* **Dispel, Drive. -lent,-ling,** *a.* प्रतिघातिन् प्रतिकारक, अपानोदिन्. *-s.* प्रति-(ती)कारः, प्रतिघातः, प्रतिवारणं.

Repent, *v. i.* अनु-पश्चात्-तप् 4 A. अनुशी 2 A, अनुशुच् 1 P,अनुतापं वह्-व्रज्-गम् 1 P. पश्चात् पीड्-खिद् pass. **-ance,** *s.* अनु-पश्चात्-तापः, अनुशयः, अनुशोकः, पश्चात्खेदः, मनस्तापः, विप्रतीसारः, पाप-दुष्कृत-खेदः. **-ant,** *a.* सानुशय, सानुताप, संजातानुताप, अनुशयविधुर-पीडित, अनुतप्त, जातानुशय जातखेद, अनुतापार्त.

Repercussion, *s.* प्रतिघातः, प्रतिपतनं.

Repertory, *s. See* **Treasury.**

Repine, *v. i.* व्यथ् 1 A, शुच् 1 P, अवसद् 1 P, खिद्-पीड्-दु-संतप्-pass.: *See* **Fret. -ing,** *s.* मनस्तापः, मनोव्यथा, शोकः.

Replace, *v. t.* (स्थाने) पुनः आ-नि-धा 3 U or निविश् *c.* or न्यस् 4 U or स्था *c.* (स्थापयति); पूर् 10, स्थाने निविश् *c.*, प्रतिनिधिं दा 3 U; 'one servant was r. ed by two' किंकरस्थाने किंकरद्वयं निवेशितं; *See* **Substitute.**

Replenish, *v. t.* (पुनः) संपूर् 10 or उप-क्लृप् *c.*

Replete, *s.* सं-पारि-पूर्ण, सं-आ-कीर्ण, परिपूरित, आ-नि-चित, आढ्य, मय (यी *f.*) in comp. **-ion,** *s.* पूर्णता, पर्याप्ति *f.*, परि-, पूर्ति *f.*

Replica, *s.* प्रतिकृति *f.*

Reply, *s.* उत्तरं, प्रति-वचनं-वाक्यं-वाच् *f.*, उक्ति *f.* **2** उत्तरपक्षः, प्रतिवादः; 'leave no room for r.' निरुत्तरीकृ 8 U. *-v. i.* दा 3 U with (*s.*), उत्तरं प्रति-पद् 4 A, प्रतिवच् 2 P, प्रतिवद् 1 P. भाष् 1 A. **2 Echo,** q. v. **-Replicant,** *s.* उत्तरवादिन् *m.*, प्रतिवादी

Report, *v. t.* आ-नि-विद् *c.*, आ-ख्या 2 P or *c.* (ख्यापयति), विज्ञा *c.* (ज्ञापयति) बुध् *c.*, वृत्तांतं लिख् 6 P, श्रु *c.*; 'he is r ed to be dead' स मृत इति श्रूयते, इति जनश्रुतिः-प्रवादः. *-s.* नि-आ-वेदनं, विज्ञापना, विज्ञप्ति *f.*, कथनं; 'written r.' आवेदनपत्रं, विज्ञप्तिलेखः. **2** ख्याति *f.*, विश्रुति *f.*, कीर्ति *f.*; 'evil or bad r.' कौलीनं, अकीर्तिः. **3** वार्ता, वृत्तांतः, प्रवादः, जन-लोक-वादः-प्रवादः-श्रुतिः-वार्ता, उपश्रुति,

जनरवः; किंवदंती; 'there goes a r.' इति जनप्रवादः &c. श्रूयते, इति प्रवादः. 4 ध्वनिः, नादः, शब्दः; *See* **Noise.** **-er,** *s.* वृत्तांतनिवेदिन् *m.*

Repose, *v. i.* विश्रम् 4 P, संविश् 6 P, शी 2 A. **2** विश्वस् 2 P, प्रति-इ 2 P. **3** आ-अव-लंब् 1 A, आ-सं-श्रि 1 U; 'r. ing confidence' विश्वासप्रतिपन्न, सविश्वासं स्थित. **-***v. t.* विश्रम् *c.*, संविश् *c.* **2** निक्षिप् 6 P, स्था *c.* (स्थापयति), नि-आ-धा 3 U. **-***s.* विश्रा(श्र)मः, विश्रांति *f.*, विरामः, उप-प्र-शमः, प्र-शांति *f.*, श्रमच्छेदः-निवृत्ति *f.*, निर्वृति *f.*

Reposit, *v. t.* नि-आ-धा 3 U, न्यस् 4 P, रक्ष् 1 P. **-ory,** *s.* निधिः, आगारं, निधानं, पात्रं, भाजनं, आश्रयः, आशयः, आधारः, कोष्ठः, रक्षणस्थानं.

Reprehend, *v. t.* भर्त्स् 10 A, परुषं निंद् 1 P, or उपालभ् 1 A; *See* **Censure.** **Reprehensible,** *a.* निंद्य, उपालभ्य, गर्हित, गर्हणीय, दूषणीय. **-Reprehension,** *s.* निंदा, गर्हा, भर्त्सनं-ना, दूषणं, उपालंभः.

Represent, *v. t.* वर्ण् 10, वि-वृ 5 U, निरूप् 10: oft. ex. by स्था *c.*; 'r. even vices as virtues' दोषानपि गुणपक्षमध्यारोपयंति, गुणपक्षे स्थापयंति (Ka. 108); 'r. in writing' अभि-,लिख् 6 P, लेख्ये निविश् *c.* or आरुह् *c.* **2** प्र-,दृश् *c.*, सूच् 10, आविष्कृ 8 U, निरूप्. **3** नि-आ-विद् *c.*, विज्ञा *c.* (ज्ञापयति); *See* **Inform.** **4** भूमौ-स्थाने-स्था 1 P, or वृत् 1 A; प्रतिनिधिः भू; 'you r. the queen' भवान् राज्ञीस्थाने वर्तते, राज्ञीप्रतिनिधिः. **5** रूपं-वेषं-ग्रह् 9 U or धृ 1 P, 10; *See* **Personate;** (a play &c.) प्रयुज् 10; 'have not seen it r. ed' न प्रयोगतो दृष्टं (Rat. 1); नाटकं प्रयोगेणाधिक्रियतां (S. 1) 'let it be r. ed on the stage'; 'r. a character' भूमिकायां वृत्; 'Urvasī r. ing Lakshmi' उर्वशी लक्ष्मीभूमिकायां वर्तमाना (V. 3). **-ation,** *s.* वर्णनं-निवेदनं, विज्ञापना-प्रदर्शनं, निरूपणं, विज्ञप्ति *f.* **2** प्रयोगः, अभिनयः. **3** प्रतिकृति *f.*, प्रतिरूपं, आलेख्यं, प्रतिच्छंदः, प्रतिमा, प्रतिमूर्ति *f.*; *See* **Picture.** **-ative,** *s.* प्रतिनिधिः, प्रतिभूः, प्रतिपुरुषः. **-***a.* प्रतिनिधीभूत; आदर्शभूत.

Repress, *v. t.* प्रति-नि-रुध् 7 U, सं-नि-यम् 1 P, नियंत्र् 10, नि-ग्रह् 9 P, प्रशम् *c.*; *See* **Check.** **-ion,** *s.* निरोधः, नियमः; निग्रहः, नियंत्रणं. **-ive,** *a.* निरोधिन्, निग्रहकारिन्.

Reprieve, *s.* विश्रामः, विरति *f.* **2** दंडव्याक्षेपः-विलंबः. **-***v. t.* दंडं व्याक्षिप् 6 P or विलंब् *c.*, व्यवहारदर्शनं व्याक्षिप्.

Reprimand, *v. t.* निंद् 1 P, भर्त्स् 10 A, उपालभ् 1 A, वाचा दंड् 10, अव-अधि-क्षिप् 6 P. **-***s.* निंदा, भर्त्सना-नं, उपालंभः, वाग्दंडः, वाक्ताडनं; *See* **Censure.**

Reprisal, *s.* प्रत्यपहरणं, प्रतिपीडनं.

Reproach, *v. t.* (परुषं) निंद् 1 P, गर्ह् 1, 10 A, उपालभ् 1 A, आक्रुश् 1 P, अप-परि-वद् 1 A, निर्-भर्त्स् 10 A, आ-अधि-क्षिप् 6 P, दुष् *c.* (दूषयति), कुत्स् 10; साक्षेपं निंद्, तिर-स्कृ 8 U, धिक्कृ, अवमन् 4 A. **-***s.* धिक्कारः, निंदा, गर्हा, तिरस्कारः, आ-अधि-क्षेपः, परि(री)वादः, उपालंभः, आक्रोशः, भर्त्सनं-ना, परुषोक्ति *f.*, वाक्पारुष्य, दुरुक्तं, वाग्दंडः, निंदा-भर्त्सना-वाक्यं. **2** दूषणं, कलंकः, अ-अप-कीर्ति *f.*; लज्जास्पदं. **-ful,** *a.* निंदागर्भ; निंदात्मक, परिवादक; better by (*s.*) in comp.: 'r. words' निंदावचनानि. **2** गर्हित, निंद्य, गर्हणीय, लज्जाप्रद. **-fully,** *adv.* साधिक्षेपं, सोपालंभं.

Reprobate, *v. t.* धिक्कृ 8 U, न्यक्कृ, दुष् *c.* (दूषयति), गर्ह् 1, 10 A: *See* **Reproach.** **-***a.*, *s.* दुर्वृत्त, दुराचार, पाप-खंडित-वृत्त, दुष्ट, पापात्मन्, दुःशील, दुरात्मन्; (of acts) दुष्ट, निंद्य, गर्ह्य. **-ion,** *s.* गर्हा, गर्हणं, अतिदुष्टता.

Reproduce, *v. t.* पुनः कृ 8 U or उत्पद् *c.* or जन् *c.*: 'he r. ed the whole speech' समग्रमेव भाषणं स यथातथमुदीरयामास. **-Reproduction,** *s.* प्रत्युत्पत्ति *f.*, पुनर्जननं.

Reprove, Reproof, *See* **Reproach.**

Reptile, *s.* सरीसृपः, सर्पणशीलः, उरगः, उरोगः-गामिन् *m.* उरंगमः, सर्पः. **-***a.* सर्पिन्, सर्पण-शील.

Republic, *s.* प्रजासत्ताक-प्रजातंत्र-राज्यं, लोक-प्रजा-प्रभुत्वं. **-an,** *a.* प्रजाप्रभुत्वविशिष्ट, लोकप्रभुत्वसंबंधिन्, (*s.*) in comp. **-***s.* प्रजाप्रभुत्ववादिन् *m.*, प्रजापक्षवादी. **-anism,** *s.* प्रजाप्रभुत्ववादः, प्रजातंत्रपक्षः.

Repudiate, *v. t.* प्रत्यादिश् 6 P, निराकृ 8 U, निर्-अप-अस् 4 U, निः-सृ *c.*, परित्यज् 1 P, प्रत्या-ख्या 2 P, अपध्वंस् *c.*, अव-निर्-धू 5, 9 U, 6 P; *See* **Reject** also. **-ion,** *s.* प्रत्यादेशः, निराकरणं, प्रत्याख्यानं, परित्यागः, अपासनं. **2** विवाहसंबंधत्यागः, दांपत्यविश्लेषः.

Repugnant, *a.* प्रतीप, विरुद्ध, प्रतिकूल, विपरीत, अत्यंतविमुख-विरक्त. **-Repugnance,** *s.* विरोधः, प्रातिकूल्यं, वैपरीत्यं, विरागः, विद्वेषः, अनिच्छा, वैमुख्यं, विमति *f.*, विरक्ति *f.*

Repulse, *v. t.* निराकृ 8 U, निः-प्रति-सृ *c.*, अवधीर् 10: प्रत्यादिश् 6 P, प्रत्या-ख्या 2 P, परा-प्रति-हन् 2 P, भंज् 7 P, वि-द्रु *c.*, (army). **-ion,** *s.* निराकरणं, निःसारणं, प्रत्यादेशः, अवधीरणं-णा, प्रतिघातः, प्रतिहननं, विद्रावणं, पराजयः, भंगः. **-ive,** *a.* अ-

प्रिय, द्विष्ट, निंद्य, बीभत्स, बीभत्सावह; *See* **Hideous. 2** प्रतिघातिन्, प्रतिसारिन्.

Repute, *v. t.* मन् 4 A. अभि-सं-°,गण् 10; *See* **Consider,** ' *r.* ed as authors ' ' कर्तृत्वेनाभिमताः. **-s.** **-ation,** *s.* कीर्ति *f.*, ख्याति *f.*, प्र-वि-°, यशस् *n.*, प्रतिष्ठा, प्रथा, प्रतिपत्ति *f.*, गौरवं, प्रसिद्धि *f.*; ' of established *r.* ' लब्धप्रतिष्ठ; ' good *r.* ' सुख्यातिः; ' bad *r.* ' दुष्कीर्तिः, अप-अ-कीर्तिः, वाच्यता, कौलीनं, दुर्नाम. **-able,** *a.* सं-, मान्य, प्रशस्य, माननीय, आदरणीय. **2** यशः-कीर्ति-कर (री *f.*), कीर्ति-मान-प्रद. **-ed,** *a.* अभिमत, जन-लोक-विश्रुत, सर्वज्ञात, जनप्रसिद्ध.

Request. *v. t.* याच् 1 A, अर्थ् 10 A, प्र-अभि-°, वि-ज्ञा *c.* (ज्ञापयति), सविनयं नि-आ-विद् *c.* **-s.** प्रार्थना, अभ्यर्थना, याचना, विज्ञापना, विज्ञप्ति *f.*, नि-आ-वेदनं, याच्ञा. **2** आकांक्षा, इच्छा, अभिलाषः, अपेक्षा; ' in general *r.* ' सर्वाभीप्सित, बहुशः इष्ट.

Require, *v. t.* प्रार्थ् 10 A. प्रच्छ् 6 P, याच् 1 A. **2** (Need) वि-,अपेक्ष् 1 A, आकांक्ष् 1 P; oft. ex. by उपयोगः, प्रयोजनं, कार्यं, with instr.: or अर्ह् 1 P: or by pot. pass. part.: ' that it is affection and should *r.* a cause is a contradiction ' स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् (Mal. 1): ' I do not *r.* his help ' न मम तस्य साहाय्येन प्रयोजनं; ' *r.* s a careful consideration ' निपुणमवेक्षणीयः, निपुणावेक्षणमर्हति. **-ment,** *s.* Ex. by (*v.*); ' all the *r.* s of man ' यद्यन्नरैरपेक्ष्यते or इष्यते. **-Requisite,** *a.* आवश्यक (की *f.*), अवश्यक, आकांक्षित, अपेक्षित. **-s.** अवश्यक-वस्तु-द्रव्यं, अपेक्षितं. **-Requisition,** *s.* प्रार्थना-नं, अपेक्षा, आकांक्षा.

Requite, *v. t.* प्रति-दा 3 U, प्रतिफलं दा, प्रत्युपकृ 8 U, निस्तॄ *c.*: *See* **Recompense, Repay;** (grudge &c.) प्रतिकृ, निर्यत् 10, शुध् *c.*, साध् *c.* **-al,** *s.* प्रतिदानं, प्रतिफलं, निस्तारः, निष्कृति *f.*, प्रत्युपकारः, पारितोषिकं [illegible] **2** प्रति(ती)-कारः, प्रतिक्रिया [illegible]

Rescind, *v. t.* [illegible] निरस् 4 U, निवृत् *c.* **-Rescission,** [illegible] वि-,लोपः, खंडनं, निरसनं; *See* **Repeal.**

Rescript, *s. See* **Counterpart.**

Rescue, *v. t.* मुच् 6 P or *c.*, मोक्ष् 10, वि-निर्-°, निस्तॄ *c.*, उद्-हृ 1 P or धृ 10: परित्रै 1 A, रक्ष् 1 P: *See* **Protect. -s.** वि-, मुक्ति *f.*, मोचनं, मोक्षः-क्षणं, उद्धारः; परित्राणं, रक्षणं, निस्तारः, तारणं; ' on, on, to the *r.* ' सत्वरं परित्रायध्वं. **-er,** *s.* उद्धर्तृ *m.*, त्राता, रक्षकः, मोक्षकः.

Research, *s.* अन्वेषणं-णा, निरूपणं, अनुसंधानं, जिज्ञासा, मार्गणं, विचारणा.

Resemble, *v. t.* सं-वद् 1 *P* (with instr.), अनुकृ 8 *U* (with gen.), अनुहृ 1 P (with acc.): ' the characters *r.* each other ' संवदंत्यक्षराणि (*Mu.* 5): gen. by तुल्य, सदृश, समान, उपम, अनुरूप in comp., (' Like ', q. v.): भव पितुरनुरूपो गुणैः (V. 5) ' *r.* your father in qualities ': देहबंधेन स्वरेण च रामभद्रमनुहरति, अस्य मुखं वत्सा मुखचंद्रेण संवदत्येव (U. 4). **2** उप-प्रति-मा 3 A, 2 P, समीक्ष्. **-ance,** *s.* सादृश्यं, सारूप्यं, तुल्यत्वं, संवादः, साम्यं, औपम्यं, उपमा, अनुकारः, अनुहारः, तुला; साधर्म्यं (in qualities). 'to bear *r.*' सादृश्यं-तुलां-अधिरुह् or समारुह् 1 P: *See* (*v.*): (तुलां यदारोहति दंतवाससा K. v. 34). **2** प्रतिकृति *f.*, प्रतिरूपं, आलेख्यं; *See* **Picture. -ing,** *a.* संवादिन्, (न केवलमस्मदंगसंवादिनी आकृतिः U. 6). अनुरूप, तुल्य, सम, समान, अनुकारिन्, अनुहारिन्.

Resent, *v. i.* अभि-प्रति-क्रुध् 4 P (with acc.) क्रुध्-कुप्-रुष् 4 P, अपकारापेक्षया कुप्. **-ful,** *a.* क्रोधिल, क्रोधशील, समन्यु, सासूय, प्रत्यपकारबुद्धि. **-ment,** *s.* कोपः, क्रोधः, रोषः, अमर्षः, मन्युः; *See* **Indignant,** &c.

Reserve, *v. t.* सं-प्रतिसं-ह् 1 P. निग्रह् 9 P. **2** (आकालांतरात्) सं-चि 5 U, नि-धा 3 U, संग्रह्, रक्ष् 1 P, अवशिष् 7 P or *c.*, त्यज् 1 P, (temporarily). आपदर्थे धनं रक्षेत् ' should *r.* his money for times of want. ' **3** गुप् 1 P, सं-वृ 5 U, अपह्नु 2 A, न स्पष्टीकृ, न विशदीकृ. **-s.** संवरणं, संवृति *f.*, नि-अप-ह्नवः, मनोगुप्ति *f.* **2** नि-,यंत्रणं-णा, निग्रहः, निरोधः; ' without any *r.* ' विवृतं, निर्व्याजं, अनियंत्रणं, निर्यंत्रणं,. **3** (Of disposition) वाग्यंत्रणं, कथा-आलाप-विरक्ति *f.*, पराङ्मुखता, अल्पभाषणं, वाग्यतत्वं. **4** संचयः, संग्रहः. **5** (Of an army) प्रति-परिग्रहः, प्रत्यासार(स)रः, पार्ष्णिग्रं सैन्यं. **-ation,** *s.* गोपनं, निग्रहः, संहारः, गुप्तिः, अपवारणं **2** नि-अप-ह्नवः, मनोगुप्तिः, संवरणं, संवृतिः. **3** परिवर्जनं, अपवादः, व्यावृत्ति *f.*; ' with this *r.* only ' अयमेव तस्यापवादः. **4** संग्रहः-हणं, संचयः. **-ed,** *a.* रक्षित, गुप्त, अवशेषित. **2** संवृतिमत्, गूढभाव, गुप्तांतःकरण, अनुत्तानहृदय, संवरणशील; वाग्यत, यंत्रितवाक्, कथा or आलाप-विरक्त or विमुख, अल्पभाषिन्, अल्पालापिन्. **-edly,** *adv.* गूढभावेन, संवृतचेतसा. **-Reservoir,** *s.* जलाशयः, तडागः-गं, जलाधारः, तोयाधारः, वापी.

Resetter, *s.* लोप्त्रग्राहिन् *m.*

Reside, *v. i.* वस् 1 P, नि-प्रति-°; अधि-स्था 1 P, अधिवस् (with acc.): निली 4 A; आश्रि 1 U, वृत् 1 A; *See* **Dwell. 2** सद् 1 P; अवक्षिप् pass. **-ence,** *s.* स्थिति *f.* वसति *f.*, वर्तनं, अधिष्ठानं, वासः; 'r. abroad' प्रवासः. **2** वसतिः, वासस्थानं, नि-, वासः, गृहं, आ-नि-लयः, आश्रयः, अधिष्ठानं, स्थानं, निकेतनं; *See* **House,** 'change of r.' स्थलांतरगमनं. **-ent,** *s.* नि-,वासिन्, or by deriv.; 'r. of this or that place' अत्रत्यः; तत्रत्यः; आयोध्यकः, कौशांबीयः. &c. **-a.** नि-,वासिन्, स्थ, वर्तिन् in comp. आश्रित, कृतालय. **-Residue,** *s.* अव-, शेषः- षं-शिष्टं. **-al,-ary,** *a.* अव-शिष्ट, शेष in comp.

Resign, *v. t.* परि-,त्यज् 1 P, उत्-वि-सृज् 6 P, हा 3 P, प्रत्यादिश् 6 P, पराक्षिप् 6 P, *See* **Abandon. 2** सं-,ऋ c. (अर्पयति), आयत्तीकृ, आ-नि-विश् c., समा-धा 3 U, न्यस् 4 U, निक्षिप्, प्रति-पद् c. **3** क्षम् 1 A, सह् 1 A; 'of those who r. themselves to you' त्वय्यावेशितचित्तानां, त्वत्समाहितचेतसां; 'r. one's claims' स्वत्वं निवृत् c., अधिकारं त्यज्; 'r. oneself to his fate' दैवाधीनीभू. **-ation,** *s.* परि-,त्यागः, उत्सर्गः, प्रत्यादेशः, पराक्षेपः; 'r. of one's claim' स्वत्वनिवृत्तिः; 'written r.' त्यागपत्रं-लेखः. **2** समर्पणं, निक्षेपणं, न्यसनं, निवेशनं. **3** क्षमा, क्षांति *f.*, संतोषवृत्ति *f.*; 'r. to God' ईश्वराधीनता; ईश्वरेच्छानुवर्तनं. **-ed,** *a.* त्यक्त, अर्पित, न्यस्त, &c. **2** क्षमावत्, तितिक्षु, शांत, ईश्वरेच्छाधीन, ईश्वरन्यस्तचित्त.

Resilient, *a.* उत्पतिष्णु. **2** स्थैतिस्थापक. **3** उल्लासित

Resin, *s.* अ-,रालः, सर्जरसः, यक्षधूपः; *See* **Pitch.**

Resist, *v. t.* प्रति-बंध् 9 P, प्रति-वि-रुध् 7 U, नि-,वार् 10, प्रत्यव-स्था 1 A; प्रतिकृ 8 U, प्रत्या-व्या-हन् 2 P; बाध् 1 A निग्रह् 9 P, प्रतिष्टंभ् 9 P, परिपंथीभू; *See* **Oppose. -ance,** *s.* प्रति-वि-रोधः, प्रतिबंधः, प्रति(ती)-कारः, प्रतियोगः, पर्यवस्थानं, प्रतिष्टंभः, प्रतियत्नः, प्रत्याघातः **-er,** *s.* प्रतियोगिन् *m.*, प्रतिबंधकः. **-less,** *a.* अनिवार्य, दुर्निवार, अप्रतिकार, अनवग्रह, दुर्निग्रह.

Resolve, *v. i.* निश्चि 5 U, निर्णी 1 P, व्यवसो 4 P, अध्यव-सो, संकल्प् c., मतिं-बुद्धिं-कृ 8 U; *See* **Determine. -v. t.** वि-ली c., वि-द्रु c. (melt); गल् c., क्षर् c.; सागरे नद्यो विलीयंते 'rivers are r. ed into the sea.' **2** वि-युज् 7 A, 10, विश्लिष् c., व्याकृ, वि-भिद् c., पृथक् कृ; *See* **Separate. 3** (Doubts) छिद् 7 P. अपाकृ, अपनी 1 P, निरस् 4 U; *See* **Dispel. -s. Resolution,** q. v. **-ed,** *a.* विश्लेषित, व्याकृत, &c. **2** कृतनिश्चय-संकल्प-मति-बुद्धि, व्यवसित, निश्चित, निर्णीत, संकल्पित. **-ent,** *s.* द्रावणं, शोथहृत्. **-er,** *s.* विभेत्तृ *m.*, छेत्ता, छिद् *m.*, in comp. **-Resolute** *a.* दृढ or स्थिर or निश्चय-संकल्प, स्थिरधी मति, धीर,धृतिमत्,*See* **Resolved also. -ly,** *adv.* दृढं, सनिश्चयं, स्थिरचेतसा. **-ness,** *s.*: *See* below. **-Resolution,** *s.* निश्चयः, निर्णयः, संकल्पः, व्यवसायः, सर्गः, अध्यवसायः; स्थिर or दृढ-निश्चयः or संकल्पः,मति *f.*, संप्र-अव-धारणा. **2** स्थिरता, स्थैर्यं, धैर्यं, धृति *f.*, निर्बंधः, स्थिरमतित्वं,अभिनिवेशः. **3** विश्लेषणं, वियोजनं, विभेदनं. **4** उपन्यासः, प्रतिज्ञा, उपक्षेपः.

Resonant, *a.* मुखरित, प्रतिध्वनित, प्रतिनादित, अनुनादिन, संघुष्ट. **-Resonance,** *s.* अनु-प्रति-नादः, प्रतिध्वनिः-स्वनः.

Resort, *v. i.* (To) सेव् 1 A, सेव्-पास्-°, श्रि 1 U, आ-सं-समा-उपा-°, उप-अभि-गम् 1 P or इ-या 2 P, अभि-उप-सृ 1 P; जुष् 6 A, (frequently). **-s.** आश्रयणं, सेवनं, गमनं, &c. **2** आश्रयः, शरणं, आयतनं, अभिगमनस्थानं. **3** गति *f.*, उपायः, शरणं.

Resound, *v. i.* प्रति-नद्-स्वन्-ध्वन् 1 P, अनु-रस् 1 P; *See* **Echo. -v. t.** प्रतिध्वन् c. &c.; निनादेन पूर् 10; 'r. ing the directions' दिशः प्रतिनिनादेन पूरयन्, दिशः प्रतिध्वानयन्. **-ing,** *a.* **Resonant,** q. v.

Resource, *s.* उपायः, गति *f.*, प्रयुक्ति *f.*, कल्पना, साधनं; 'having no other r.' अनन्यगतिक. **2** (r. s) विभवः, द्रव्यसाधनं, आयः, वित्त-द्रव्य-सामग्री, अर्थः, धनं; 'of small r. s' अल्पविभव.

Respect, *v. t.* पूज् 10, अर्च् 1 P, 10; सं-मन् c., आदृ 6 A, सेव् 1 A, भज् 1 U, सं-भू c., सत्कृ 8 U, पुरस्कृ. **2** अपेक्ष् 1 A, उद्दिश् 6 P; *See* **Refer, Relate. -s.** अपेक्षा, उद्देशः, संबंधः, अनुषंगः, विषयः; 'with r. to the result' फलापेक्षया, फलमुद्दिश्य. **2** सं-,मानः, पूजा, अभि-,अर्चनं, आदरः, संभावना, प्रश्रयः, गौरवं, पुरस्कारः, सत्कारः, अर्हणा, अर्चा, भक्ति *f.* **3** दृष्टि *f.*, अपेक्षा. **4** विषयः, प्रकरणं; वस्तु *n.*, अर्थः. **5** (r. s) नमस्कारः, प्रणामः, प्रणति *f.*, अभिवंदनं, प्रणिपातः, सभाजनं; 'in this r.' अत्र विषये; 'in all r. s' सर्वथा, 'pay one's r. s' प्रणम् 1 P, सभाज् 10, प्रणिपत् 1 P. **-able,** *a.* पूज्य, माननीय, &c.; विशिष्ट, आर्य, सप्रतिष्ठ, शुभ; 'a r. person' आर्य-सु-जनः; 'of a r. family' अभिजात. अभिजनवत्, कुलीन. **2** मध्यम, सामान्य, नातिशुभ. **-ably,** *adv.* आर्य,

उदार, in comp.; आर्यवत्, शिष्टवत्, सगौरवं; 'r. dressed' उदारनेपथ्यभृत्, आर्यवेषधारिन्. **-ful,** *a.* सादर, सप्रश्रय, सगौरव, सविनय, आदर-मर्यादा-शील, मानपुरःसर, आदर-मान-पूर्व. **-fully,** *adv.* सादरं, सप्रश्रयं, सविनयं. **-ing,** *a.* उद्दिश्य, अधिकृत्य, अपेक्ष्य; *See* **Regarding. -ive,** (Own) *a.* Ex. by स्व-स्व, ('Own' q. v.): 'they went to their r. houses' स्वं स्वं गृहं ते जग्मुः 'in their r. places' स्वेषु स्वेषु स्थानेषु. **2** सापेक्ष, अकेवल, अविविक्त, अन्यसंबद्ध; इतरेतर-अन्योन्य in comp. **-ively,** *adv.* यथाक्रमं, यथानुक्रमं, पौर्वापर्येण, प्रत्येकं प्रत्येकं.

Respire, *v. i.* उत्-नि-श्वस् 2 P, प्र-अन् 2 P. **-ation,** *s.* श्वासः, श्वासोच्छ्वासः, प्राणः. **-atory,** *a.* श्वास in comp.: 'r. organ' श्वासेंद्रियं.

Respite, *s.* विरामः, विश्रामः, विरति *f.*, अवकाशः, विलंबः, विच्छेदः, प्र-उप-शमः. **-***v. t.* विश्रामं-अवकाशं-दा 3 U.

Resplendent, *a.* देदीप्यमान, विभ्राजमान, अतितेजस्; *See* **Bright, Splendid.**

Respond, *v. i.* प्रति-वच् 2 P, प्रति-वद् 1 P, उत्तरं दा 3 U; *See* **Reply. -ent,** *s.* प्रतिवादिन् *m.*, प्रत्यर्थिन्, उत्तरवादिन् *m.*, **-Response,** *s.* उत्तरं, प्रतिवचनं, प्रतिवाक्यं. **2** प्रतिवादः, उत्तरं. **-Responsible,** *a.* अनुयोगाधीन, अनुयोज्य, आज्ञाधीन, प्रष्टव्य; oft. by उत्तरं दा: 'you are r. for this act' अस्य त्वयैवोत्तरं दातव्यं. **2** धूर्वह, धूर्वोढृ, धुरंधर, धुरीण. **-Responsibility,** *s.* भारः, भरः, धुर् *f.*: 'the whole r. of the kingdom' राज्यस्य समस्तो भरः, राज्यधुरा. **2** अनुयोगाधीनता, प्रष्टव्यता. **-Responsive,** *a.* उत्तरदायिन्. **2** संवादिन्.

Rest, *v. i.* विश्रम् 4 P, वि-आ-रम् 1 P, (कार्यात्) निवृत् 1 A; निश्चलीभू 1 P, स्थिरीभू, निश्चेष्टीभू. **2** (Lean against) आलंब् 1 A, उपा-समा-आ-श्रि 1 U; नि-उप-धा pass.: 'with her face r. ing on her left hand' वामहस्तोपहितवदना (S. 4): oft. by भरं कृ 8 U (with loc.); 'r. ing on his three hoof (legs)' खुरत्रये भरं कृत्वा (H. 2): वृक्षे भारं निधाय, यष्टिमवलंब्य, &c. **3** प्र-उप-शम् 4 P, सुखिन्-निर्वृत-स्वस्थ-*a.* भू. **4** शी 2 A, स्वप् 2 P, सं-विश् 6 P, नि-द्रा 2 P, नि-ली 4 A. **5** स्था 1 P, भू, वृत्; 'r. with' अवलंब्, अपेक्ष् 1 A, अधीन-आयत्त-*a.* भू; *See* **Depend** (on): 'further than this r. s with fate' भाग्यायत्तमतः परं (S. 4). **-***v. t.* विश्रम् c., शी c., संविश् c. **2** निविश् c., न्यस् 4 U, अवलंब् c., स्था c., आ-नि-धा 3 U; चापे विजयाशंसां निदधौ 'r. ed his hope of victory on his bow'; सकलरिपुजयाशा यत्र बद्धा सुतैस्ते (Ve. 5) 'on whom your sons had r. ed their hopes of overthrowing all enemies.' **-***s.* विश्रा(श्र)मः, विश्रांति *f.*, कार्यव्यापार-निवृत्तिः. **2** (Of a body) स्थिरता, निश्चलता, निश्चेष्टता, अचलता. **3** सुखं, सौख्यं, स्वास्थ्यं, निर्वृति *f.*, प्र-उप-शमः-शांति *f.*; *See* **Ease. 4** अवलंबनं, आधारः, स्थानं. **5** निद्रा, शयनं, संवेशः-शनं. **6** अवशेषः-शिष्टं; अन्य, इतर, अपर (*a.* pl.) (of persons): आदि, प्रभृति, in comp. **7** यति *f.*, अवसानं; 'at r.' निश्चल, निश्चेष्ट, अचल, स्थिर; सुस्थ, प्र-उप-शांत, निर्वृत, विश्रांत; निर्व्यापार, निरुद्योग. **-ing,** *a.* आलंबित, आश्रित, नि-उप-हित, स्थित; स्थ, वर्तिन् in comp.; 'r.-place' शयन-विश्राम-स्थानं. **-less,** *a.* व्याकुल, पर्या-समा-कुल, पारिप्लव, अशांत, विह्वल, अस्वस्थ, व्यग्र, अनिर्वृत, उद्विग्न. **2** चपल, चंचल, चल; सदागति, सास्पंद. **3** उन्निद्र, विनिद्र, निर्णिद्र; 'passes r. nights' उन्निद्रा रजनीं गमयति (Mal. 3). **-lessly,** *adv.* अनिर्वृतं, व्यग्रं; चंचलतया. **-lessness,** *s.* अनिर्वृतिः, अस्वास्थ्यं, उद्वेगः, व्यग्रता, चापल्यं, चांचल्यं, &c.

Restaurant, *s.* उपाहारगृह

Restitution, *s.* प्रतिदानं, प्रत्यर्पणं, प्रत्यानयनं.

Restive, Restiff, *a.* दुष्ट, दुर्मार्गप्रस्थित, अदम्य, दुर्दम, प्रतीप, दुर्धर, दुर्विनीत, उद्धत.

Restore, *v. t.* पुनर्-प्रति-दा 3 U or ऋ c. (अर्पयति), प्रति-पद् c., निर्यत् 10, परावृत् c., प्रत्यानी 1 P; पुनर्लभ् 1 A, प्रति-पद् 4 A, प्राप् 5 P, (when passively used) प्रत्यर्पितस्वांगः 'with his body r. ed to him': स्मरं वपुषा स्वेन नियोजयिष्यति (K. iv. 42) 'will r. to Cupid his body'; 'r. ed the universe to the rule of Indra' पुनरपि त्रिभुवनमिंद्रवशमगात् or नीतं, इंद्रशासनायत्तं कृतं; 'r. ed to its pristine splendour' पुराणशोभामधिरोपितायां (वसतौ) (R. xvi. 42), 'r. to life' जीव् c., सोच्छ्वास-*a.* कृ 8 U, असून् प्राप् c.; 'r. ed to consciousness' लब्धसंज्ञ, प्रत्यागतचैतन्य. **-ation,** *s.* प्रतिदानं, प्रत्यर्पणं, प्रतिपादनं, निर्यातनं, परावर्तनं, प्रत्यानयनं, उद्धारः, पूर्वावस्थाप्रापणं, &c. **-ative,** *a.* अग्निवर्धन (नी *f.*), सत्त्व-बल-वर्धन. **-***s.* बलवर्धनं, बल्यं, वाजीकरणं. **-er,** *s.* प्रतिदातृ *m.*, प्रत्यर्पयितृ.

Restrain, *v. t.* सं-अव-नि-रुध् 7 U, निग्रह् 9 P, नि-सं-यम् 1 P, नि-प्रति-बंध् 9 P, आ-

वृ 5 U, संहृ 1 P, नि-,यंत्र् 10; *See* **Forbid, Control,** also. **2** (Legally) आसिध् 1 P.&c. **-er,** *s.* नियंतृ *m.*,निग्रहीता, निरोधकः. **-Restraint,** *s.* निग्रहः, नि-अव-रोधः, सं-नि-यमः, नि-,यंत्रणं-णा, प्रतिबंधः, स्तंभः, प्रतिरोधः, बाधा, यमः, जयः,दमः (of the senses). **2** आसेधः; 'r. of speech' वाग्यमः, वाक्संयमः.

Restrict, *v. t.* निरुध् 7 U, नियंत्र् 10, अवधृ 10, नि-सं-यम् 1 P, निबंध् 9 P,परि-मा 3 A. 2 P, निग्रह् 9 P;'my actions being thus r.ed on all sides' एवं सर्वतो निरुद्धचेष्टाप्रसरस्य मे (Mu. 3);बाध् 1 A, व्यावृत् c. (scope) अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः (R. xv. 7) 'can r. the scope of a rule.' **-ed,** *a.* नियत, समर्याद, सावधिक, परिमित &c.; *See* **Limited. -ion,** *s.* सीमा, इयत्ता, नियमः, मर्यादा, अवधिः, परिच्छेदः, निबंधः, निरोधः, अवधारणा, व्यावृत्ति *f.*, यंत्रणा; 'without r.' स्वैरं, यथेच्छं, अनियंत्रणं. **-ive,** *a.* व्यावर्तक, नियामक, परिच्छेदक, अवधारण; तुशब्दोऽवधारणार्थः, व्यावृत्त्यर्थकः (S. B.) 'has a r. sense.'

Result, *v. i.* अव-पर्यव-सो 4 P, वि-,परिणम् 1 U; *See* **End. 2** उत्पद्-निष्पद् 4 A, प्र-सं-उद्-भू 1 P, जन् 4 A, प्रवृत् 1 A; *See* **Produce**; gen. ex- by (*s.*): 'it will r. in nothing' तन्निरर्थकं भवेत्; 'it will r. in his destruction' तस्य नाश एव फलं भवेत्. -*s.* परिणामः, फलं. **2** अर्थः, गुणः, निष्पत्तिः, सिद्धि *f.*: अंतः, अवसानं, शेषः,उदर्कः; पाकः; 'good r.' शुभफलं. **3** सिद्धांतः, मथितार्थः,निश्चितार्थः; 'producing no r.' निष्फल, निर्गुण, व्यर्थ. **-ing,** *a.* ज, जन्य, उद्भव, फल in comp.; *See* **Produced.**

Resume, *v. t.* पुनः-भूयः-आदा 3 A or ग्रह् 9 U or आप् 5 P or लभ् 1 A, प्रत्याहृ 1 P; 'let us r. (the thread of) our discourse' प्रकृतं-प्रस्तुतविषयं-अनुसंदधाम or अनुसराम; oft. by पुनः-भूयः-आरभ् 1 A or कृ, with other words; 'r. ed their fighting' पुनर्योद्धुमारेभिरे; अतः परं पुनः कथयिष्यामि (M. 4) 'I shall r. my story from this point afterwards'; 'he r.ed his discourse' पुनर्वक्तुं प्रचक्रमे. -*s.* सारः, संग्रहः, सारार्थः. **-Resumption,** *s.* पुनरादानं, पुनर्ग्रहणं, प्रत्याहारः.

Resurrection, *s.* पुनरुज्जीवनं, मृतोत्थापनं.

Resuscitate, *v. t.* पुनर्जीव् c. or उत्था c. (उत्थापयति), उज्जीव् c., प्रत्युद्-जीव् c., **-ion,** *s.* पुनर्जीवनं, उत्थापनं, उज्जीवनं, प्रत्युज्जीवनं.

Retail, *s.* अल्पशः विक्रयः, पण्यक्रयः. -*v. t.* अल्पशः विक्री 9 A or पण् 1 A. **-er,** 'r.-dealer' *s.* अल्पशः पण्यविक्रयिन् *m.*, क्षुद्र-वणिज् *m.*

Retain, *v. t.* धृ 1 P, 10, रक्ष् 1 P, धा 3 U; ग्रह् 9 U. **2** (Servants) वेतनं दत्त्वा नियुज् 7 A, 10, व्या-पृ c., उप-जी 1 A, (कर्मकरानुपनयते S. K.); (in memory) चित्ते-मनसि कृ 8 U or नि-धा or निविश् c., अवधृ. **-er,** *s.* अनुयायिन् *m.*, अनुगः, अनुचरः, पार्श्वकः, अनुगामिन् *m.*, अनुजीविन् *m.*, सेवकः, भृत्यः, किंकरः, आश्रितः; *See* **Servant,** 'body of r.s' परिवारः, भृत्य-अनुयायि-वर्गः. **-Retention,** *s.* धारणा-णं, ग्रहणं. **2** (Faculty) *See* below: 'r. of urine' मूत्रसंगः. **-Retentive,** *a.* धारणावत्, धारणक्षम; 'r. faculty' धारणाशक्ति *f.*, धारणा, मेधा, धारणावती धीः, ग्रहणसामर्थ्यं. **2** धर, ग्राहिन् in comp., धारक.

Retaliate, *v. t.* प्रति-कृ 8 U. प्रत्यपकृ; (वैरं) निर्यत् 10, शुध् c., साध् c.: प्रति-हिंस् 7 P. **-tion,** *s.* प्रतिक्रिया, प्रति(ती)कारः, प्रत्यपकारः, प्रतिहिंसा, वैरसाधनं-शुद्धिः-निर्यातनं.

Retard, *v. t.* प्रति-नि-रुध् 7 U, स्तंभ् 9 P, प्रतिबंध् 9 P, बाध् 1 A, नि-वृ c.; *See* **Obstruct. 2** विलंब् c., व्याक्षिप् 6 P,गति अवरुध् or स्तंभ्. **-ation,** *s.* निरोधः, प्रतिबंधः, वेग-गति-रोधः, विलंबः, व्याक्षेपः. **-ed,** *a.* निरुद्ध, विलंबितगति, अवरुद्धवेग.

Reticence, *s.* मौनं, संवृति *f.*, मूकभावः, वाग्यमः. **-Reticent,** *a.* मौनावलंबिन्, संवृतिमत्, यंत्रितवाच्, वाग्यत; *See* **Reserved.**

Reticular, *a.* जालाकार, जालरूप. **-Reticulation,** *s.* जालकर्मन् *m.*

Retina, *s.* नेत्रांतः पटलं.

Retinue, *s.* परिजनः, परिवारः, परिबर्हः, परिच्छदः, अनुयायि-भृत्य-वर्गः, परिचराः, अनुचराः.

Retire, *v. i.* अपक्रम् 1 U, 4 P. अपगम् 1 P, अप-या-इ 2 P, चल् 1 P, परावृत् 1 A; एकपार्श्वे स्था 1 P. **2** विश्रामार्थं उद्योगात्-विरम् 1 P or कार्य-अधिकारं-त्यज् 1 P, विविक्तवृत्तिं सेव् 1 A, सेवां त्यज्; 'r. from the world' सर्वसंगं परित्यज्, संन्यस् 4 U, विविक्ते वस्; शांतिमार्गोत्सुकोऽभूत् (R. vii. 71) 'wished to r. from the world'. **-ed,** *a.* विविक्त, गुप्त, विजन, गूढ, प्रच्छन्न, एकांत, निभृत, निर्जन; *See* **Lonely,** 'a r. spot' रहःस्थानं; विविक्तं. **2** (Disposition) संवृतिमत्, गूढ, अनुत्तान; *See* **Reserved. 3** त्यक्तकर्मन्, विविक्तसेविन्,त्यक्ताधिकार; 'a r. person' संन्यासिन् *m.*,मुक्तसंगः. **-ment,** *s.* अपसरणं, अपक्रमणं, अपगमनं, &c. **2**

निर्जन-विविक्त-स्थानं, रहःस्थानं. 3 विविक्तवृत्ति *f*., अधिकार-कार्य-त्यागः; विविक्तसेवनं; संन्यासः. **-ing,** *a*. अपक्रामिन् *&c*. 2 विविक्त-प्रिय-सेविन्, अधृष्ट; *See* **Reserved.**

Retort, *v. i*. प्रत्युत्तरं दा 3 U, प्रत्यवस्कंद् 1 P, प्रत्याक्षिप् 6 P, प्रतिकृ 8 U, प्रत्यभि-युज् 7 A, 10. **-s.** प्रत्युत्तरं, प्रत्यवस्कंदनं, प्रत्यपवादः, प्रत्यभियोगः, प्रत्यारोपः. 2 वक्रयंत्रं.

Retrace, *v. t*. (One's steps) प्रत्यावृत्, निवृत्, 1 A; *See* **Return.**

Retract, *v. t*. प्रत्या-ख्या 2 P, प्रत्यादिश् 6 P (word, promise, &c.) निवृत् c., निवृत् 1 A (with abl.); व्यतिक्रम् 1 U, 4 P, अतिचर् 1 P. **-ion,** *s*. प्रत्याख्यानं, प्रत्यादेशः, निवर्तनं, उक्त-त्यागः-व्यतिक्रमः.

Retreat, *v. i*. अप-या 2 P- गम्-सृ 1 P, अपक्रम् 1 U, 4 P, प्रतिनि-नि-प्रत्या-वृत् 1 A: *See* **Retire.** 2 प्र-वि-द्रु 1 P -अपधाव् 1 P, पलाय् 1 A. **-s.** अपसरणं, अपक्रमः-मणं, अपयानं, परावर्तनं, परावृत्ति *f*., अपगमः, प्रतिनिवृत्तिः. 2 पलायनं, प्र-वि-द्रावः. 3 शरणं, आश्रयस्थानं, निलयः, विविक्त or निर्जन-देशः or स्थानं.

Retrench, *v. t*. न्यूनीकृ 8 U, ह्रस् c., अल्पीकृ, अवच्छिद् 7 P, अवकृत् 6 P, खंड् 10, अप-चि 5 U. **-ment,** *s*. अवच्छेदः, खंडनं, व्ययच्छेदः, न्यूनव्ययः, व्ययापचयः.

Retribution, *s*. प्रति(ती)कारः, प्रतिफलं; *See* **Revenge. -Retributive, -Retributory,** *a*. प्रतिकारिन्, प्रतिकार in comp.

Retrieve, *v. t*. पुनः प्राप् 5 P or लभ् 1 A, प्रत्याहृ 1 P, उद्धृ 1 P, प्रति-,समा-धा 3 U; *See* **Recover,** 'irretrievably gone' असन्निवृत्तये गतं.

Retrocede, *v. i* परावृत् 1 A; *See* **Return. -Retrocession,** *s*. परावर्तनं.

Retrograde, *a*. प्रतीप, प्रतिलोम, वक्र, परावृत्त, विपरीत, प्रतीपगामिन्; 'in a r. direction' वि-,प्रतीपं; 'turn in a r. direction' प्रतीपयति (D.), परावृत् c. **-v. i.** परावृत् 1 A, प्रतीपं गम् 1 P; विपरीतं या-इ 2 P. 3 **Decline, Decay,** q. v. **-ation, Retrogression,** *s*. प्रतीपगमनं, विपरीतगमनं-गति *f*.

Retrospect, *s*. अतीतपर्यालोचनं, सिंहावलोकनं, अनुदर्शनं, भूतावलोकनं. **-ive,** *a*. अनुदर्शिन्, गतावलोकिन्. 2 भूतापेक्ष, गतकालसापेक्ष.

Return, *v. i*. नि-प्रत्या-प्रतिनि-वृत् 1 A, प्रति-या 2 P, पुनर्या, पुनर्-इ 2 P, प्रत्यागम्-परापत् 1 P, प्रति with words for 'Come' 'Go', q. v.; 'it is gone never to r.' असंनिवृत्त्यै तदतीतमेव (S. 6): 'r. to life' चेतनां लभ् 1 A or प्रतिपद् 4 A, सोच्छ्वास-*a*. भू. 2 **Answer,** q. v. **-v. t.** प्रति-दा 2 P, 3 U, प्रति-ऋ c. (अर्पयति), निर्यत् 10, प्रति-पद् c. 2 पुनः आनी; 'r. good for good' प्रत्युपकारं कृ 8 U; 'r. an injury' प्रत्यपकृ, प्रतिहिंस् 7 P. **-s.** निवृत्ति *f*., प्रत्यागमनं, प्रत्यावृत्तिः, परापतनं, पुनरागमनं, निवर्तनं, प्रत्यायानं. *&c*.; 'on your r.' प्रतिनिवृत्ते त्वयि. 2 प्रत्यर्पणं, प्रतिदानं, निर्यातनं, प्रतिकारः. प्रत्युपकारः. 3 परिवर्तः, परिवृत्ति *f*., पर्यायः, आवर्तः. 4 फलं, लाभः, प्राप्ति *f*., उदयः, उत्पन्नं; 'in r.' प्रति in comp.; 'injury in r.' प्रत्यपकारः; 'benefit in r.' प्रत्युपकारः; 'in r. for' विनिमयेन, परिवर्तनेन.

Re-unite, *v. t*. पुनः संयुज् 7 U, 10 or सं-धा 3 U. **-Re-union,** *s*. पुनः संयोगः-समागमः-संसर्गः.

Reveal, *v. t*. वि-वृ 5 U, प्रकाश् c., व्यंज् 7 P or c., आविष्कृ 8 U, व्यक्तीकृ, प्रकटीकृ; ख्या c., ज्ञा c. (ज्ञापयति); 'the missiles r. ed themselves to us' स्वतःप्रकाशान्यावयोरस्त्राणि (U. 6); 'the sacred hymns were r. ed to the sages' ऋषयः मंत्राणां द्रष्टारः, मंत्रान् स्वयं ददृशुः; 'r. a secret' रहस्यं प्रकाश् c. or भिद् 7 P &c. **-er,** *s*. प्रकाशकः, व्यंजकः, भेदकः. **-Revelation,** *s*. विवरणं, प्रकाशनं, व्यक्तीकरणं, आविष्करणं. 2 श्रुतिप्रकाशः; ऐशोन्मेषः.

Revel, *s*. निर्भरं पानगोष्ठीसुखं, संप्रीति *f*. तुमुलः पानमहोत्सवः. **-v. i.** अनु-भू 1 P or सेव् 1 A with (*s*.). **-ry,** *s*. *See* (*s*.) above.

Revenge, *s*. प्रत्यपकारः, प्रति(ती)कारः, प्रतिहिंसा, प्रतिद्रोहः, वैरसाधनं-निर्यातनं-शुद्धि *f*., प्रतिक्रिया. 2 (Desire for r.) जिघांसा, प्रत्यपकारबुद्धि *f*. **-v. t.** (Persons) वैरनिर्यातनं or वैरसाधनं-शुद्धिं कृ 8 U (with gen.): प्रतिहिंस् 7 P, प्रतिद्रुह् 4 P, प्रत्यपकृ. 2 (Insult &c.) निर्यत् 10, साध् c., शुध् c., प्रतिकृ, निस्तॄ c. **-er,** *s*. प्रत्यपकारकः, प्रतिहिंसकः. **-ful,** *a*. प्रतिकारपरायण, प्रत्यपकार or प्रतिहिंसा-शील or बुद्धि, प्रत्यपकारेच्छु, अक्षमिन्, अमर्षण. **-fully,** *adv*. प्रत्यपकारबुद्ध्या.

Revenue, *s*. करः, बलिः, आयः, उदयः, भागधेयः, राजस्वं.

Reverberate, *v. i*. प्रतिध्वन्-नद् 1 P, अनुनद्-गर्ज् 1 P. **-v. t.** प्रतिध्वन् c. &c. 2 प्रतिक्षिप् 6 P, प्रतिहन् 2 P. **-ion,** *s*. प्रतिध्वनिः-नादः-शब्दः. 2 प्रतिक्षेपः.

Revere, *v. t*. सं-,मन् c., पूज् 10, सं-भू c., पुरस्कृ 8 U, सत्कृ, भज् 1 U. उपास् 2 A. आदृ 6 A, अर्च् 1 P, 10. **-ence,** *s*. सं-, मानः, अर्चना, प्रश्रयः, पूजा, सत्कारः, आदरः,

सपर्या,पुरस्कारः, उपासना, अर्हणा, भक्ति *f.*; 'his r.'तत्रभवान्,भवान्,'your r.' अत्रभवान्,'act of r.'नमस्कारः, नमस्या, प्रणिपातः, प्रणामः, अभिवंदनं. -*v. t. See* (*v.*). -**ed,** *a.* पूज्य, अर्चनीय, सं-,मान्य, आर्य, पूजार्ह, नमस्य, उपास्य; oft. ex. by सुगृहीतनामन् (when dead) पूज्यपाद; 'r. sir' भगवन्. -**ent,-ential,** *a.*भक्तिमत्, सादर, सप्रश्रय, मानपुरःसर, भक्तिपूर्व; 'with a r.bow' भक्तिप्रणामं कृत्वा. -**ently,** *adv.* भक्त्या, भक्तिपुरःसरं, सादरं, सप्रश्रयं.

Reverie, *s.* ध्यानं, चिंतनं, भावना.

Reverse, *s.* पृष्ठं, पृष्ठभागः. **2** परिणामः, विकारः, परिवृत्ति *f.*; 'r. s of fortune' दैवदुर्विपाकः, भाग्यविपरिणामः, अत्याहितं, आपद्-विपद् *f.*; *See* **Misfortune. 3** विपर्ययः, व्यत्ययः, व्यत्यासः, विपर्यासः, व्यतिक्रमः, वैपरीत्यं, वि-प्रति-पक्षः; 'if r. be the case' विपर्यये तु; 'r. of' ex. by इतर in comp.; 'r. of red' रक्तेतर, &c. -*a.* विपरीत, व्यत्यस्त, वि-प्रति-लोम, प्रतीप, विपर्यस्त, विरुद्ध, व्यतिक्रांत, विभिन्न-पक्ष; 'r. order' विपर्ययः, व्यतिक्रमः, प्रातिलोम्यं; 'in the r. order' वि-प्रति-लोमं, विपर्यासेन, व्यत्यासेन. -*v. t.* परिवृत् c., विपर्यासं नी 1 P, परावृत् c., विपर्यस् 4 U, व्यत्यस्; अधोमुखीकृ 8 U; *See* **Overturn, Change,** (in law) प्रत्यादिश् 6 P, परावृत् c., अधरीकृ, खंड् 10, प्रतिक्षिप् 6 P. -**al,** *s.* परा-परि-वृत्ति *f.* -वर्तनं. -**ed,** *a.* विपर्यस्त, परिवृत्त, वि-प्रति-लोम, अधरोत्तर, अधोमुख, &c.; *See* (*a.*); 'my fortune being r.' परिवृत्तभाग्यतया, भाग्यविपर्यासात्, &c. -**ion,** *s.* परा-प्रत्या-वृत्तिः-वर्तनं, विपर्यासः. -**ly,** *adv.* विपर्ययेण, वि-प्रति-लोमं, व्यतिक्रमेण, व्यत्यासेन.

Revert, *v. i.* प्रत्या-परा-नि-वृत् 1 A, प्रत्यागम् 1 P. -*v. t.* **Reverse,** q. v. -**Reversion,** *s.* प्रत्यावृत्ति *f.*, परावर्तनं, पुनरागमनं. **2** उत्तराधिकारः. -**ary,** *a.* उत्तरभोग्य; 'r. right' शेषभोगाधिकारः; 'r. heir' उत्तराधिकारिन्.

Review, *v. t.* (Book) गुणदोषं वि-विच् 3, 7 U or निरूप् 10 or परीक्ष् 1 A. **2** पुनः ईक्ष् or दृश् 1 P or आ-अव-लोक् 1 A, 10, पुनः विचर् c. or परीक्ष् or निरूप् 10 or अनुसं-धा,प्रत्यालोच् 10. -*s.* गुणदोषविवेचनं, गुणागुणविचारः-निरूपणं-परीक्षा; परीक्षा-क्षणं, निरूपणं. **2** पुनरीक्षणं, पुनर्दर्शनं, प्रत्यालोचनं, पुनः विचारः- निरूपणं-परीक्षा. -**er,** *s.* गुणदोषविवेचकः.

Revile, *v. t.* निर्-,भर्त्स् 10 A, गर्ह् 1, 10 A, आ-अधि-क्षिप् 6 P, अपवद् 1 A, निंद् 1 P, आक्रुश् 1 P. -**er,** *s.* निर्भर्त्सकः, निंदकः, अपवादकः. -**ing,** *s.* निर्-,भर्त्सनं-ना, गर्हणं-णा, अपवादः, आक्रोशः, आ-अधि-क्षेपः; उपालंभः, वाक्पारुष्यं; *See* **Abuse, Reproach.**

Revise, *v. t.* पुनः दृश् 1 P or ईक्ष् 1 A or विचर् c.; *See* **Review. 2** (पुनः) शुध् c., सं-वि-परि-शुध् c. -**al,-ion,** *s.* पुनर्दर्शनं, पुनः परीक्षा, संशोधनं.

Revive, *v. t.* जीव् c., प्रत्युत्-उत्-सं-°, (fig also); पुनः जीव् c., प्र-वि-बुध् c., चेतनां-संज्ञां-लभ् c. (लंभयति) or प्राप् c., प्रत्या-समा-श्वस् c., पुनः उत्-स्था c. (उत्थापयति), उद्-धृ 10. **2** पुनः प्रवृत् c., नवीकृ 8 U. -*v. i.* प्रत्युत्-उत्-सं-जीव् 1 P, पुनः जीव्; संज्ञां-चेतनां-लभ् 1 A or प्राप् 5 P or आ-प्रति-पद् 4 A प्र-वि-बुध् 4 A, सं-उत्था 1 A, प्रत्या-समा-श्वस् 2 P. **2** पुनः प्रवृत् 1 A. -**al,** *s.* संजीवनं,प्रत्युत्-उत्-जीवनं, (fig. also); संज्ञाप्राप्ति *f.*, चेतनागमः, चेतनालाभः, प्र-अव-बोधः. **2** पुनरुत्थानं. समुत्थानं, पुनः स्वास्थ्यं, पुनः स्वास्थ्यप्राप्तिः. **3** उद्धारः, पुनःप्रवृत्तिः.

Revoke, *v. t.* निवृत् c., खंड् 10, निरस् 4 U. -**Revocation,** *s.* निवर्तनं, खंडनं, प्रत्यादेशः; *See* **Repeal.**

Revolt, *v. i.* अभि-,द्रुह् 4 P, व्युत्था 1 A, कोपं उत्पद् c., शासनं अति-इ 2 P or उल्लंघ् 1 A, 10. -*s.* राजद्रोहः, प्रकृतिकोपः; *See* **Rebellion, Mutiny,** 'fall into r.' (fig.) विसंवादिन्-विरोधिन्-*a.* भू 1 P. -**ing,** *a.* बीभत्स, अतिगर्ह्य, अतिद्वेष्य; 'a r. scene, बीभत्सालोकः.

Revolve, *v. i.* परिवृत् 1 A; वि-व्या-आ-वृत्, परि-भ्रम् 1, 4 P, घूर्ण् 6 P, 1 A, वि-परि°, लुठ् 6 P; 'that matter (idea) constantly r. ing in his mind' तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वात् (Ka. 67). -*v. t.* Causal of roots above. **2** (मनसा) विचर् c.. वितर्क् 10, विमृश् 6 P, आलोच् 10; *See* **Consider.** -**ing,** *a.* परिवर्तिन्, परि-,भ्रमिन्. -**Revolution,** परिवर्तः-र्तनं, परिवृत्ति *f.*, आवर्तः. आवृत्तिः, घूर्णनं. **2** (Of time &c.) परि-आ-वर्तः, पर्यायः, चक्रं, भ्रमणं, भ्रांति *f.*, युगशतपरिवर्तान् 'for r. s of ages;' 'r. of time' कालचक्रं, कालावर्तः. **3** गति *f.*, प्रवृत्तिः; 'r. of a planet' (time) भगणः. **4** राज्यपरिवर्तः-परिवृत्तिः. -**ary,** *a.* (*s.*) in comp. -**ist,** *s.* राज्यपरिवृत्तिवादिन्. -**ize,** *v. t.* सर्वथा-साकल्येन-परिवृत् c. -**Revulsion,** *s.* विरागः, विरक्ति *f.*

Reward, *s.* पारितोषिकं, प्रतिफलं, प्रतिदानं; दक्षिणा, मूल्यं, वेतनं; 'the r. due to a spiritual teacher' गुरुदक्षिणा; 'deserving

a r. ' दृक्षिण्य, दक्षिणीय. -v. t. पारितोषिकं &c. दा 3 U, परितुष् c., दानेन संतुष् c. or सं-भू c., मूल्यं दा. 2 सफलीकृ 8 U, कृतार्थयति (D.); ' his labour was r. ed ' तस्य प्रयत्नः सफलो बभूव.

Rhapsody, s. असंगतप्रबंधः, असंबद्धकविता. **-ic,-ical,** a असंगत, असंबद्ध, निरन्वय, अनन्वित.

Rhetoric, s. अलंकारशास्त्रं-विद्या,साहित्यशास्त्रं **-al,** a. आलंकारिक (की f.), अलंकाररूप, अलंकार in comp.: 'r. style' अलंकारयुता-आलंकारिकी-भाषासरणिः; ' r. expression ' अलंकारः, वाक्यालंकारः. **-ian,** s. अलंकारशास्त्रज्ञः. 2 वाग्मिन् m., प्रवक्तृ m.: See **Orator.**

Rheum, s. (Of the eye) दूषि-षी f., दूषिका. 2 श्लेष्मन् m., कफः; क्लेदनः, क्लेदकः. **-y,** a. (Eye) क्लिन्नाक्षि n., चुल्लः, चिल्लः, पिल्लः; ' having r. eyes ' क्लिन्नाक्ष, चुल्ल, चिल्ल, पिल्ल. 2 श्लेष्मल-ण, कफिन. **-Rheumatic,** a. वातीय, वात in comp. 2 वातकिन्; वातुल, वातग्रस्त, वातोपहत, वात-वायु-ग्रस्त. **-Rheumatism,** s. संधिवातः-वायुः (of the joint); वातः, वायुः, वातव्याधिः-रोगः.

Rhinoceros, s. गंडः, गंडकः, खड्गिन् m., ' the female r. ' खड्गधेनुः.

Rhombus, s. तुल्यचतुर्भुजः.

Rhyme, s. यमकः-कं, मिलिताक्षरं. 2 पद्यं, कविता. **-er,** s. कविता-पद्य-कारः, कुकविः.

Rhythm, s. तालः, लयः. **-ical,** a. लयताल-अनुगत; तालबद्ध.

Rib, s. पर्शुका, पार्श्वकं, पार्श्वास्थि n.: ' the r. s taken together ' पंजरः-रं. 2 पोर्लिंदः. 3 शलाका (of umbrellas). 4 रेखा.

Ribald, a. See **Obscene** &c.

Ribbon, Riband, s. पट्टबंधः, दुकूलपट्टः.

Rice, s. (Plant) शालिः, कलमः, नीवारः, व्रीहिः (various kinds). 2 तंडुलः, धान्यास्थि n. 3 (Boiled) अन्नं, ओदनः-नं, भक्तं; See **Food**; 'r. with milk and sugar ' पायसं, परमान्नं; ' scum of r. ' मासरः, आचामः, निस्र(स्रा)वः, भक्तमंडः; ' scorched r. ' भिस्सटा, दुग्धिका; fried r. ' धानाः (f. pl.); ' ear of r. ' कणिशः-शं, धान्यशीर्षकः.

Rich, a. धन-वित्त-द्रव्य-वत्, धनिन्, धनवित्त-शालिन्, सधन, महा-बहु-धन, अर्थवत्, धनिक, धनाढ्य, विभवसंपन्न, धनसमृद्ध, श्रीमत्, लक्ष्मीवत्; समृद्ध, धनेश्वर, लक्ष्मीश; संपत्तवत्, शालिन्, युक्त in comp. with **Wealth,** q. v. 2 (Costly) महार्ह-र्घ, बहुमूल्य,महामूल्य, अतिप्रतापवत्. 3 आढ्य, बहुल, प्रचुर, पूर्ण, वत्, समृद्ध, संपन्न, मय in comp.: ' r. perfume ' बहलामोदः; ' r. in beauty ' रूपाढ्य; गुणाढ्य, बहुलरत्न, &c. 4 सत्त्व-सार गुण-वत्, स्फीत, बहुफलप्रद्, उर्वरा (भूमिः), सस्याढ्य. 5 उज्ज्वल, सुप्रकाश, अतिशोभन (colours). 6 घृत-मूत-पूर्ण. **-es,** s. धनं, अर्थः, विभवः, वित्तं, द्रव्यं; See **Wealth.** 2 धनाढ्यता, सधनता, धनबाहुल्यं. **-ly,** adv. बहुधनेन, प्रभूतं, भूरि, महामूल्येन, अतिशोभया, अतिप्रतापेन, सश्रीकं; ' r. decorated ' अतिशोभया प्रसाधित, सविशेषमंडित. **-ness,** s. धनाढ्यता, सश्रीकता, सधनता, स्फीतता, महार्घता,अतिशोभा, प्रतापः; बाहुल्यं, समृद्धि f., संपद् f.: ' r. of beauty ' रूपसंपद्, लावण्यातिशयः; ' r. of expression ' वचसामुदारता (Mal. 1).

Rick, s. (Of corn or hay) राशिः, संचयः.

Rickets, s. बालग्रहः.

Rickety, a. शिथिलसंधि, अस्थिर, अदृढसंधि; (building) जीर्ण, जर्जरित.

Rid, v. t. मुच् 6 P :or c., मोक्ष् 10, वि-,मुच् c., उद्-हृ 1 P; ' to get r. of ' अप-नी 1 P, निराकृ, त्यज् 1 P, अप-हृ 3 P, निः-सृ c., अपास् 4 U; oft. by निर् pr.; 'r. of thorns ' निष्कंटकीकृ; ' r. of difficulties ' निर्विघ्नीकृ. **-a.** वि-,मुक्त, वर्जित, हीन, रहित, गत, वीत, हृत, निर्, अ in comp.; कंटकहीन, निःशल्य, &c. **-dance,** s. मुक्ति f., मोक्षः, उद्धारः, शोधनं.

Riddle, s. प्रहेलिका, प्रवह्लिका, प्रश्नदूती; गूढं, कूटप्रश्नः. 2 शोधनी, चालनी. -v. t. छिद् c. 2 व्यध् 4 P: See **Perforate.**

Ride, v. i. अश्वेन संचर् 1 A or गम् 1 P or या 2 P or चल् 1 P, अश्वेन &c. वह् pass. -v. t. (अश्वं &c.) आ-अधि-समा-अध्या-रुह् 1 P, अध्या-आ- क्रम् 1 U, 4 P, अधिष्ठा 1 P, अध्यास् 2 A. -s. अश्वेन संचरणं or विहरणं. **-er,** s. अश्वारोहः, अश्वारोहिन् m., अश्वारूढः. 2 आरोहिन् m., आरूढः. **-ing,** s. अश्वारोहणं. **-a.** आरूढ, आरोहिन्, आरोह, आश्रयिन् in comp.

Ridge, s. कटकः-कं, उत्संगः. 2 पृष्ठं. 3 सेतुः, धरणः, आलि f., पिंडलः. **-y,** a. सकटक.

Ridicule, v. t. उप-अव-हस् 1 P, उपहास्यतां नी 1 P, उपहासास्पदं कृ 8 U, अवहासास्पदीकृ, आ-अव-क्षिप् 6 P; See **Contemn,** also; ' I shall be r.-ed ' गमिष्याम्युपहास्यतां (R. 1. 3); ' to be r. ed ' उपहास्यतां गम् 1 P or या 2 P. -s. उप-अव-हासः-हसनं, आ-अव-क्षेपः, अवज्ञा, अवहेलना, उपहास्यता. **-ous,** a. अव-उप-हास्य, हासास्पदीभूत, हास्ययोग्य, उपहासार्ह, हासास्पदं, हासकर (री f.), हासोत्पादक.

Rife, a. सर्वत्र प्रचलित, प्रवृत्त, प्रचल, बहुल.

Riff-raff, s. अधमाः, प्राकृत-पृथग्-जनाः.

Rifle, *s.* आग्नेयास्त्रं. –*v. t.* अप-हृ 1 P; *See* **Rob.**

Rift, *See* **Fissure.**

Rig, *v. t.* सज्जीकृ 8 U, उपकरणैः उपक्लृप् c. **2** *See* **Frolic. -ging,** सज्जा, सामग्री, परिच्छदः, रज्ज्वादिसाधनं; पोतसज्जा.

Right, *a.* दक्षिण, वामेतर, सव्येतर, अपसव्य; 'to the r.' दक्षिणतः; दक्षिणेन; 'r. hand' अग्रहस्तः-करः, दक्षिणपाणिः. **2** उचित, न्याय्य, युक्त, उपपन्न, सम्यच्, यथान्याय, धर्म्य, साधु, समंजस, सत्-सु in comp.; 'r. path' सन्मार्गः, सुपथः. **3** सत्य, यथार्थ, अवितथ, तथ्य; *See* **True;** 'Priyamvada is r.' or 'says r.-ly' अवितथमाह प्रियंवदा (S. 1); 'you are r.' सत्यं-यथार्थं-आह-भवान्. **4** सरल, ऋजु, अवक्र; 'r. angle' समकोणः, ऋजुकोणः. –*s.* दक्षिणपार्श्वः-दिक्; दक्षिणः, अपसव्यं; 'on the r.' दक्षिणतः, दक्षिणस्यां दिशि. **2** न्यायः, धर्मः, न्याय्यता, न्यायिता, औचित्यं, याथार्थ्यं, नीति *f.*, युक्तता. **3** सत्यता, तथ्यता, शुद्धता. **4** अधिकारः, स्वत्वं, स्वाम्यं, सत्ता; oft. ex. by अर्ह् 1 P; 'a woman has no r. to independence' न स्त्री स्वातंत्र्यमर्हति. –*adv.* युक्तं, न्यायतः, स्थाने, साधु, उचितं, यथोचितं, यथान्यायं, उपपन्नं, सम्यक्; 'I acted r. in delivering her into the charge of the queen' एनां देवीहस्ते निक्षिपता मया युक्तमेवानुष्ठितं (Rat. 1). **2** सत्यं, यथार्थं, सरलं, ऋजु; सु-अति pr. –*interj.* साधु, युक्तं, भद्रं, बाढं. –*v. t.* ऋजूकृ 8 U, सुस्थीकृ, समा-प्रतिसमा-धा 3 U. –*v. i.* सरल-ऋजु-*a.* भू 1 P. **-eous,** *a.* न्यायपरायण-पर, साधुवृत्त, पवित्र, न्यायाचार, सुशील; (of acts) न्याय्य, युक्त; *See* **Just. -eously,** *adv.* न्यायतः, धर्मेण. **-eousness,** *s.* सदाचारः, साधुवृत्तं. **-ful,** *a.* अधिकारिन्, स्वत्वविशिष्ट. **2 Just,** q. v. **-fully,** *adv.* साधिकारं. **-ly,** *adv.* उचितं, सत्यं, यथार्थतः, परमार्थतः, यथार्थं, स्थाने, युक्तं, यथाधर्मं, यथान्यायं, न्यायतः, सम्यक्. **2** सत्यं; *See* **Truly.**

Rigid, *a.* कठोर, कर्कश, उग्र, दारुण, परुष. **2** दृढ, घन, कठिन, अशिथिल, असृदु. **-ity, -ness,** *s.* कठोरता, कठिनता, दृढता, घनता, काठिन्यं. **-ly,** *adv.* दृढं, कठिनं, अशिथिलं, *See* **Strict.**

Rigmarole, *s.* अनर्थककथा.

Rigour, *s.* दृढता, काठिन्यं, अशैथिल्यं. **2** उग्रता, कठोरता, कर्कशता, निष्ठुरता. **-ous,** *a.* कठोर, निष्ठुर, उग्र, परुष, तीक्ष्णदंड, असौम्य, कर्कश, कठिन. **2** सूक्ष्म; *See* **Strict. -ously,** *adv.* उग्रं, निष्ठुरं, परुषं.

Rile, *v. t.* क्षुभ् c., कुप् c.

Rill, *s.* क्षुद्रसरित् *f.*, क्षुद्रनदी, कुल्या.

Rim, *s.* प्रांतः, अंतः, धारा, कर्णः (of ships).

Rime, *s.* *See* **Hoar-frost.**

Rind, *s.* त्वच् *f.*, वल्कः-ल्कं, वल्कलः-लं, शल्कं, चर्मन् *n.*, कंचुकः.

Ring, *v. i.* रण्-क्वण् 1 P, वि-रु 2 P, शिंज् 2 A. –*v. t.* वद् c., वद् c., आहन् 2 U, नद् c., क्वण् c., 'r. the bell' घंटां वादय, घंटानादं कुरु. –*s.* अंगुली(री)यं-यकं, ऊर्मिका; 'signet r.' अंगुलिमुद्रा, मुद्रा. **2** वलयः-यं, मंडलं, चक्रं; 'dancing in a r.' मंडलनृत्यं. **3** मंडलं (of persons). **4** रंगः. **5** शिंजितं, क्वणितं, क्वणनं, नि-,क्वा(क्व)-णः, रवः, नादः; 'r.-leader' नायकः, अग्रणीः, मुख्यः, प्रवर्तकः, मुखरः, प्रधानराजद्रोहिन् *m.* (of conspirators); 'r.-worm' दद्रुमंडलं, मंडलकुष्ठं; 'having r.-worm' दद्रु(द्रू)णः, दद्रुरोगिन्.

Ringlet, *s.* अलकः, चूर्णकुंतलः, कुरलः.

Rinse, *v. t.* जलेन प्रक्षल् 10, (जलं) उप-स्पृश् 6 P, आचम् 1 P. **-ing,** *s.* आचमनं, उपस्पर्शः.

Riot, *s.* संमर्दः, संक्षोभः, तुमुलं, कोलाहलः, विप्लवः. **2** यथेच्छपानोत्सवः, विषयसुखातिरेकः, तुमुलोत्सवः. **3** सं-अव-मर्दः (संभूय कृतः); राजाभिद्रोहः, प्रजाक्षोभः, प्रकृतिकोपः; 'to run r.' मर्यादां अतिक्रम् 1 U, 4 P or अति-इ 2 P. –*v. i.* संक्षोभं इ 2 P, संरंभं गम् 1 P, तुमुलं कृ 8 U. **2** सुखोपभोगे निमग्न-*a.* भू 1 P, तुमुलरवेण उत्सवं सेव् 1 A or कृ. **-er,** *s.* तुमुलसंक्षोभकारिन् *m.* **-ous,** *a.* तुमुल-क्षोभ-कारिन्, तुमुलोत्सवकारिन्. **-ously,** *adv.* तुमुलशब्देन, सकोलाहलं.

Rip, *v. t.* वि-,दृ 9 P or c., विपट् 10, नि-भिद् 7 P, निकृंत् 6 P; *See* **Tear.** –*s.* विदरः, विपाटनं.

Ripe, *a.* पक्व, परि-वि-सु-°, पक्वतां आपन्न, परिणत, पाकोन्मुख (स्त्री *f.*), फलोन्मुख, प्रौढ; 'r. in years' परिणतवयस, प्रवयस्, प्रवृद्ध, वयोवृद्ध; 'r. to meet one's doom' विनाशोन्मुख, पक्व. **2** सिद्ध, संपन्न; *See* **Perfect. 3** सिद्ध, सज्ज, सन्नद्ध; *See* **Ready. -Ripen,** *v. i.* पाकं इ 2 P or व्रज् 1 P, पाकाभिमुख-पाकोन्मुख-*a.* भू 1 P, पच् pass., उपचि pass.; 'coldness r.-ed into downright hatred' अनादरः (कालक्रमेण) उपचीयमानः साक्षाद्द्वेषस्य परां कोटिं इयाय. –*v. t.* पच् 1 P, कृ with (*a.*); *See* **Mature. -ness,** *s.* परि-वि-पाकः, परिणति *f.*, परिणामः. पक्वावस्था, पक्वदशा.

Riparian, *a.* नदीतटसंबंधिन्.

Ripost, भंगिभाषणं, सरसोक्ति *f.*

Ripple, *s.* तरंगः, वीचि-ची *f.*, ऊर्मि *f.*, भंगः. **-v.** *i.* क्षुभ् 4 P, 1 A, चलोर्मि-सतरंग-*a.* भू 1 P. **-ing,** *a.* चलोर्मि, क्षुब्ध, प्रचलदूर्मि; सतरंग, तरंगाकुल, उत्तरंग.

Rise, *v. i.* उत्था 1 P, समुत्था 1 A, (in all senses); 'r. ing from the bed' सुप्तोत्थित, सुप्तशयन; 'do not r. to receive their elders' नाभ्युत्तिष्ठति गुरून् (Ka. 108). **2** उद्गम् 1 P, उद्-इ 2 P, उदय् 1 A, उत्पत् 1 P, ऊर्ध्वं गम् or व्रज् 1 P, उद्-वृत् 1 A; आ-अधि-रुह् 1 P, आक्रम् 1 A (पूर्वदिशं); उत्क्रम् 1 P. **3** प्रति-भा 2 P, निर्भा, प्रादुर्भू 1 P, आविर्भू, दृश्-लक्ष्-pass. **4** प्र-, जन् 4 A, उत्पद् 4 A, प्रवृत, उद्-सं-प्र-भू, निःप्र-सृ, निःगम्. **5** (Advance) उत्था, प्र-,वृध् 1 A, उपचि-pass., अधिकीभू, प्रबलतर-*a.* भू; 'r. ing enemy' उत्तिष्ठमानः शत्रुः. **6** प्रतिपत्तिं-उन्नतिं-प्राप् 5 P, उत्क्रम्, उत्क्रम् pass. **7**(Against) अभिद्रुह् 4 P (with acc.), द्रुह् (with dat.), व्युत्था 1 A. **8** (As sea) क्षुभ् 1 A, 4 P, ऊर्मिमालाकुल-क्षुब्ध-*a.* भू. **-s.** सं-,उत्थानं (fig. also). **2** उदयः, उद्गमः-मनं, उत्पातः, ऊर्ध्वगतिः; 'he owes his r. to me' मत्तः लब्धोदयः; 'r. and fall' पातोत्पातौ. **3** उत्पत्ति *f.*, प्रभवः, उद्भवः, संभवः, उद्गमः, प्रवृत्ति *f.* प्र-उप-क्रमः, आरंभः. **4** वृद्धि *f.*, उपचयः, आधिक्यं. **5** उन्नति *f.*, उत्कर्षः, प्रतिपत्ति *f.* पदवृद्धिः, उदयः; 'to give r. to' उत्पद् c., जन् c. **-ing,** *s.* उत्थानं, उदयः, उद्गमः &c.; 'r. to receive another' अभ्युत्थानं, प्रत्युद्गमः. **2** प्रजा or प्रकृति-क्षोभः or प्रकोपः; *See* **Mutiny. 3 Tumour,** q. v.; 'r. ground' उन्नतभूमिः, उन्नस्थानं, उत्सेधः.

Risible, *a.* हासजनन (-नी *f.*), हास्यास्पदं, हासकर (-री *f.*), हासोत्पादक.

Risk, *s.* संशयः, संदेहः, शंका, भयं, संकटं, 'run the r. of losing all' सर्वनाशसंशये आत्मानं पत् *c.* **-v.** *t.* संशये न्यासे क्षिप् 6 P or पत् c.; *See* **Danger.**

Rite, *s.* क्रिया, विधिः, कर्मन् *n.*, कार्यं, आचारः, संस्कारः, नियमः, कल्पः; 'scriptural r.' शास्त्रविधिः-कर्म, शास्त्रोक्तक्रिया. **-Ritual,** *a.* वैधिक-नैयमिक (-की *f.*), विध्यनुरूप, शास्त्रोक्त, विधि-क्रिया in comp. **-s.** क्रियासंस्कारः-विधिः-पद्धतिः-शास्त्रं. **-ist,** *s.* संस्कारशास्त्रज्ञः.

Rival, *v. t.* स्पर्ध् 1 A, प्रति-परि-°, (with instr.), संघृष् 1 P, अहमहमिकया-परस्परजिगीषया-यत् 1 A, वि-,जि desid. (जिगीषति); oft. by प्रतिद्वंद्विन्, प्रतिस्पर्धिन्; 'with hands r. ing young foliage (in beauty)' किसलयोद्भेदप्रतिद्वंद्विभिः करतलैः (S. 4); चंद्रच्छायाप्रतिस्पर्धी or -प्रतिद्वंद्वी &c. **-a.. -s.** प्रति-,स्पर्धिन्, प्रतियोगिन्, वि-,जिगीषु, प्रतिपक्ष, सपत्न, परस्परसंघर्षिन्, अभिभवेच्छु; by प्रति in comp.: 'r. combatant' प्रतियोधः; 'r. army' प्रतिबलं &c.: 'r. woman' सपत्नी; 'a r. Kesava' अपरः केशवः, प्रति-केशवः; 'a r. to Sri' प्रत्यादेश इव श्रियाः (V. 1).**-ry,** *s.* प्रतिस्पर्धा, प्रतियोगिता, वि-,जिगीषा, अहमहमिका, प्रतिद्वंद्विता, संघर्षः, सापत्न्यं, प्रतिपक्षता; विरोधः, वैरं.

Rive, *v.* *See* **Tear.**

River, *s.* नदी, सरित्, सिंधुः, आ(अ)पगा, निम्नगा, तरंगिणी, स्रोतोवहा, तटिनी, ह्लादिनी, स्रोतस्विनी, धुनी, शैवलिनी, द्वीपवती, स्रवंती, निर्झरिणी 'a small r.' कुल्या, अल्प-कृत्रिम-सरित्; 'confluence of r. s' संभेदः, सिंधुसंगमः; 'watered by r. s' नदीमातृक.

Rivet, *v. t.* कील् 10, कीलेन बंध् 9 P, दृढं बंध्; अभिनि-विश् c., सस्ज् c.; 'to be r. ed' कीलित-दृढबद्ध-*a.* भू, सस्ज् 1 U (sight): स्थाने खलु सज्जति दृष्टिः (M. 1); 'all eyes were r. ed on him' नेत्रव्रजाः तस्मिन्निपेतुः (R. vi. 7), तस्मिन् दृष्टिः सक्ताभूत्; बध्नाति मे चक्षुः चित्रकूटः (R. xiii. 47), दयिते प्रत्युप्तस्य चक्षुषः (U. 3); आलिखित इव रंगः (S. 1) 'the audience is r. ed (to the spot) with attention.'. **-s.** कीलः-लकः-कं, शलाका.

Rivulet. *s.* क्षुद्र-कु-सरित् *f.*, अल्प-क्षुद्र-नदी.

Road, *s.* मार्गः, पथिन् *m.*, अध्वन् *m.*, वर्त्मन् *n.*, वीथि-थी *f.*, रथ्या, सरणि-णी *f.*, पदवी, पद्धति-ती *f.*; 'high r.' राजमार्गः-पथः; 'common r.' प्रचारः; 'difficult r.' दुर्गसंचरः, संक्रमः, दुर्गमार्गः; 'dreary, lonely r.' प्रांतरं, शून्यमार्गः; 'crossing of r. s' चतुष्पथं, शृंगाटकं; *See* **Way.**

Roam, *v. i.* परि-,अट् 1 P, परि-,भ्रम् 1, 4 P, वि-सं-चर् 1 P; '. about' इतस्ततः वि-ह्र 1 P or चर् or भ्रम्. **-ing,** *s.* परि-,अटनं, परि-, भ्रमणं, विचरणं.

Roar, *v. i.* गर्ज् 1 P, स्तन् 1 P, नद् 1 P, रस् 1 P, रु 2 P, नर्द् 1 P, अट्टहुंकृ 8 U (of lion); 'a r. ing river' घर्घररवा सरित्. **2** वि-आ-उत्-व्याकुश् 1 P, प्रणद्, घुष् 10; 'r. ing with pain' आर्तनादं मुच्. **-s.,-ing,** *s.* गर्जितं, स्तनितं, गर्जनं-ना, नर्दनं, विरावः, महा-दीर्घ-गंभीर-शब्दः-नादः; घनध्वनिः, दीर्घरावः-घोषः; हुंकारः. **2** नादः, वि-आ-क्रोशः, निर्घोषः, शब्दः, स्वरः, ध्वनिः.

Roast, *v. t.* भ्रस्ज् 6 P; 'r. on a spit' शूलाकृ 8 U. **2** तप् 1 P or c., दह् 1 P, **-ed,** *a.* भ्रष्ट, भृष्ट; 'r. on a spit' शूल्य.

[illegible], [illegible], [illegible].
Rob, v. t. मुष् 10, मुष् 9 P, लुंठ् 1 P, 10, [illegible] 1 P, (with gen. of person). **-ber**, s. [illegible], चोर(चौ)रः, [illegible], [illegible], लुंठकः, [illegible]; *See* Thief. **-bery**, s. अपहरणं, [illegible], [illegible], चौर्यं, [illegible], [illegible], लुंठनं.
Robe, s. वसनं, [illegible]. **-v. t.** वसनं परि-धा 3 U, वस् 2 A; *See* Dress.
Robust, a. [illegible], [illegible], [illegible] ([illegible] f.), [illegible], मांसल, [illegible], [illegible], [illegible]; 'r. body' [illegible], [illegible]. **-ly**, adv. [illegible], [illegible]. **-ness**, s. [illegible], [illegible], मांसलता.
Rock, s. [illegible], [illegible], [illegible], [illegible], [illegible], [illegible], [illegible] m., [illegible], [illegible] m., [illegible], (small); *See* Stone, 'r.-salt' [illegible], [illegible], [illegible], [illegible]. **-v. t.** [illegible] c. (rock to sleep); [illegible] (D.), [illegible], प्र-वि-चल् c. **-v. i.** [illegible] (D.), [illegible] वि-प्र-चल् 1 P; *See* Waver. **-y**, a. [illegible] ([illegible] f.), [illegible], [illegible], [illegible] ([illegible] f.), (s.) in comp.
Rocket, s. [illegible], [illegible].
Rod, s. दंडः, [illegible] (of metal) यष्टि f., वेत्रं (of cane.)
Rodent, a. [illegible].
Rodomontade, s. [illegible], [illegible].
Roe, s. [illegible], [illegible], [illegible]. 2 मृगी, हरिणी.
Rogue, s. धूर्तः, [illegible], [illegible], शठः, [illegible], वंचकः, [illegible], [illegible], [illegible], [illegible], [illegible], [illegible] m., [illegible]. **-ery**, **-ishness**, s. [illegible], [illegible], [illegible], [illegible], &c. **-ish**, a. धूर्त, शठ, [illegible]; *See* (s.) **-ishly**, adv. [illegible], [illegible], [illegible].
Roisterer, s. [illegible] m.
Role, s. [illegible], [illegible] n.
Roll, v. i. वि-लुठ् 6 P, वि-लुठ् 1, 4 P, 2 परि-[illegible]-लुठ् 1 A, परि-भ्रम् 1, 4 P, घूर्ण् 6 P, 1 A; (about) प्र-वि-चल् 1 P, घूर्ण्, वि-लुठ् 1 P; 'with eyes r.-ing about' [illegible], [illegible], [illegible]. 3 (On, by &c.) [illegible] 2 P, [illegible] 1 P, [illegible] 1 U, 4 P, परि-[illegible], परि-इ; 'as days r.-ed on' [illegible] [illegible], [illegible], 'a cloud r.-s on through the air' [illegible] [illegible] (Mr. 5); 'which has r.-ed out at the foot of the Vindhya' [illegible] [illegible] (Me. 19). **-v. t.** [illegible]-परि-वृत् c., घूर्ण् c., [illegible] c., &c.; 'r. down' [illegible] [illegible] 1 P; 'r.-ing down corpses' [illegible] ([illegible]).

2 [illegible] c., वि-स्तृ°, 3 [illegible] 8 U, [illegible], [illegible] 10. 4 [illegible] c., [illegible] 10, [illegible] 5 U. **-s.** [illegible], परिवर्तनं, &c. 2 [illegible], [illegible], [illegible]. 3 [illegible] f. **-er**, s. [illegible], [illegible], [illegible]. 2 [illegible] (for flour). 3 [illegible]. **-ing**, s. [illegible], परि-[illegible], घूर्णनं, परि-[illegible], &c. **-a.** घूर्णत् वि-[illegible], [illegible].
Rollic, v. i. *See* Frolic.
Romance, s. [illegible], [illegible]. **-v. i.** [illegible] [illegible] 6 P or [illegible] 9 P. **-Romantic**, a. [illegible], [illegible], [illegible]. 2 [illegible], [illegible], [illegible], [illegible]. 3 [illegible], [illegible].
Romp, v. i. [illegible] [illegible] 1 P, [illegible] [illegible] 1 P, (U. 4). **-s.** [illegible], [illegible]. 2 [illegible], [illegible], [illegible], [illegible].
Roof, s. [illegible] f., पटलं; 'the wooden frame of a r.' [illegible], [illegible]; 'the edge of a r.' [illegible], [illegible]. 2 [illegible] n. (of the mouth). **-v. t.** [illegible] [illegible] 10. **-ed**, a. [illegible], [illegible] **-less**, a. [illegible]; (fig.) [illegible].
Rook, s. [illegible], [illegible]. 2 *See* Cheat, s. 2. **-ery**, s. [illegible].
Room, s. वेश्मन् n., प्र-कोष्ठः, [illegible], [illegible], [illegible], [illegible]; 'upper r.' [illegible], [illegible]; 'inner r.' [illegible], [illegible], [illegible]. 2 अ-[illegible], स्थानं, [illegible], भूमि f., [illegible] [illegible] [illegible] [illegible] (K. III. 2) 'Vasava made r. for him' &c.; 'there is r. for doubt here' [illegible]. 3 [illegible], [illegible], [illegible], [illegible], [illegible], [illegible]; 'want of r.' [illegible], [illegible]; 'giving no r. for envy' [illegible] [illegible]; 'make r.' [illegible] [illegible], [illegible]. 4 (Stead) स्थानं, [illegible]; *See* Instead of. **-y**, a. [illegible], [illegible], [illegible], [illegible], [illegible].
Roost, s. [illegible] f., [illegible], [illegible] or [illegible] or [illegible]. **-v. i.** शी 2 A, [illegible] 2 P, [illegible] 4 A, [illegible] 1 P, [illegible] 1 U.
Root, s. मूलं, in all senses; [illegible], [illegible] &c.; [illegible], [illegible] (Foot, q. v.); [illegible]; [illegible], [illegible] (fibrous); 'bulbous r.' कंद-दं; 'to the r.s' [illegible], [illegible], [illegible]; 'the r. of a branch' [illegible]. 2 [illegible], [illegible], मूलं, [illegible] in comp. (of animals only). 3 मूलं, [illegible], [illegible] f., [illegible], [illegible], कारणं, [illegible], [illegible] f.; 'having for its r.' मूल, हेतु, &c. in comp.; [illegible] [illegible], &c. 4 (Of a word) मूलं, [illegible], [illegible].

योनिः; 'r.-meaning' मूलार्थः, यौगिकार्थः, व्युत्पत्तिसिद्धः. 5 (Of numbers) मूलं, पदं; 'to extract a r.' मूलीकृ 8 U. -v. i. 'take r.' मूलं बंधू 9 P. -v. t. दृढं निखन् 1 P or वहृ c.; ex. by 'r.-ed'. 2 (Up) उन्मूल् 10, समूलं उद्-हृ 1 P, उत्पट् 10, उत्खन्, व्यपवहृ c., उच्छिद् 7 P. -ed, a. दृढ-बद्ध-मूल, रूढ-घून-मूल.

Rope, s. रज्जु f., गुणः, दामन् f. n., शुल्वं, वराटकः-कं, संदानं, वटः-टी-टं; 'the rope and bucket of a well' उद्घाटनं, घटीयंत्रं; 'r.-dancer' सूत्रायणः,कलायणः; 'r.-ladder' रज्जुसोपानं; 'r.-maker' रज्जुकारः. -y, a. रज्जुधर्मन्, श्यान, सांद्र.

Rosary, s. अक्षमाला, अक्षसूत्रं, जपमाला-सूत्रं.

Rose, s. जपापुष्पं, ओड्रपुष्पं; (tree or flower) जपा-वा; सेवती, शतपत्री; 'r.-apple' जंबू f.; (fruit) जंबुफलं, जांबवं. -y, a. पाटल, जपावर्ण. 2 जपारूप. -Roseate, a. 'r.-coloured' पाटल, जपासवर्ण.; 2 बहिरमणीय, दृष्टिमनोहर.

Rot, v. i. पूतीभू 1 P, वि-,गल् 1 P, विली 4 A, दुर्गंध a. भू. -v. t. गल् c., विली c., पूतीकृ 8 U. -Rotten, a. पूतिगंधि, दुर्गंध, विगलित, विलीन; पूतीभूत, दुष्ट, दूषित. 2 क्षीणसत्त्व, असार, निःसत्त्व.

Rotate, v. i. भ्रम् 1, 4 P, चक्रगत्या भ्रम्, परिवृत् 1 A; *See* Revolve. -ion, s. भ्रमणं, भ्रांति f., आ-परि-वर्तः-वृत्ति f., चक्रावर्तः, चक्रगतिः. 2 पर्यायः, क्रमः, आनुपूर्व्यं; 'in r.' पर्यायेण, पर्यायवृत्त्या, चक्रवत्, पर्यायानुसारेण, अनुपूर्वं. -ory,-Rotary, a. चक्रावर्तिन्, चक्रगति.

Rote, s. आवृत्ति f., अभ्यासः, आवर्तनं; 'learn by r.' (अर्थज्ञानं विना) कंठस्थ-a. कृ 8 U, अभ्यस् 4 U; 'learnt by r.' कंठस्थ, अभ्यस्त.

Rotund,-ity, *See* Round,-ness.

Rough, a. नतोन्नत, विषम, असम, अश्लक्ष्ण. 2 रु(रू)क्ष, परुष, कर्कश, कठिन, असमृण, असौम्य, अमृदु, दुःस्पर्श; (in disposition) निष्ठुर, उग्र, कटु, कठोर; (in manners) असभ्य, अशिष्ट, असंस्कृत, स्थूल, वन; 'r measurement' स्थूलमानं. 3 अपटु, अदक्ष, अनिपुण, अकुशल, स्थूल. 4 (Sea) क्षुब्ध, तरंगाकुल, उत्तरंग, वायुक्षुब्ध, पवनाहत. 5 लोमश, लोमावृत, स्थूललोमन्; 'r.-cast' स्थूलं कल्प् c. or वि-धा 3 U; 'r.-draw' स्थूलं लिख् 6 P; 'r.-hew' स्थूलं तक्ष् 1, 5 P or छिद् 7 P; 'r.-rider' अश्वशिक्षकः. -en, v. t. रूक्षी-स्थूली-कृ 8 U. -ly, adv. रूक्षं, परुषं, कर्कशं, स्थूलं, निष्ठुरं, &c. -ness, s. वैषम्यं, रूक्षता, पारुष्यं, कर्कशत्वं, उग्रता, कठोरता, स्थूलता, अदक्षता; संक्षोभः, ऊर्मिप्रलोठनं, &c.

Round, a. वर्तुल, गोल, वृत्त, वृत्ताकार, निस्तल, मंडलाकार, चक्राकृति, वृत्त-गोलरूप, वलयाकार. 2 पीन, पीवर, उन्नत. 3 अवक्र, असंदिग्ध, परिस्फुट, निश्चित, परिच्छिन्न, व्यक्त; *See* Decided. 4 (Number) समग्र; शून्यांतक. -s. मंडलं, चक्रं, वर्तुलं, गोलः, वलयः-यं. 2 परिभ्रमणं, परिवर्तः, पर्यायः, आवृत्ति f., आवर्तः. 3 चक्रमार्गः, गतिः f.; (of a ladder) भंगि f., आरोहणं, सोपानं. -prep. परितः, अभितः, (with acc.); समंततः, समंतात् (with gen.) -adv. परि in comp. (with verbs). 2 चक्रवत्, मंडलाकारेण, वलयरूपेण, चक्ररूपेण; 'turn r.' परिवृत् c., परिभ्रम् c.; 'turning r.' चक्रभ्रांतिः, परिभ्रमणं, मंडलावृत्तिः; 'to get r.' मतं परिवृत् c. 3 सर्वतः, समंततः, समंतात्, विश्वतः, सर्वदिक्षु; 'the whole year r.' समग्रवर्षं. -v. t. वर्तुलीकृ 8 U, गोलीकृ. 2 परिगम् 1 P, परि-या-इ 2 P. 3 समा-धा 3 U; संस्कृ; 'well-r. ed' सुवृत्त; (fig.) सुसमाहित, सुसंस्कृत; 'r.-about' वक्र, कुटिल, असरल; समंततः, अभितः; &c. -ly, adv. अवक्रं, सपरिच्छेदं, सुव्यक्तं, स्पष्टार्थं. -ness, s. वृत्तता, गोलत्वं, वर्तुलता, पीनता, अवक्रता, स्पष्टता, &c.

Rouse, v. t. (From sleep) वि-प्र-बुध् c., जागृ c., उत्था c. (उत्थापयति), निद्रां भंज् 7 P or भिद् 7 P. 2 उत्पद् c., जन् c., उद्-प्र-बुध् c., उत्तिज् c., उद्यम् 10, उत्था c., उद्दीप् c., प्रोत्सह् c.; 'r. to action' क्षुभ् c., चेष्ट् c., प्रचुद् 10, कार्ये प्रवृत् c. -v. i. Awake, q. v. -s. पानोत्सवः, सग्धि f., सपीति f.

Rout, v. t. भंज् 7 P, वि-द्रु c., प्र-वि-ध्वंस् c., प्र-दलाय c. -s. भंगः, विध्वंसः, विद्रावः, सैन्यभंगः, व्यूहभेदः, बलव्यसनं. 2 जनसंमर्दः; *See* Mob. 3 कोलाहलः, तुमुलरवः, कलकलः. -ed, a. विद्रावित, भग्न, प्रपलायित; भग्नव्यूह. उर्तिजल, समुत्पिंज, कांदिशीक.

Route, s. *See* Road.

Routine, s. क्रमः, पर्यायः, अभ्यासः; 'daily r.' दिनक्रमः. दैनिककार्यपरिपाटी-परंपरा; 'r- work' नित्यकर्मन् n. 'usual r.' नित्यक्रमः, नित्याभ्यासः.

Rove, v. i. पर्यट् 1 P, परि-,भ्रम् 1, 4 P, प्र-वि-चर् 1 P. -er, s. परिभ्रमकः, पर्यटनकृत् m., भ्रमणशीलः. 2 दस्युः, चोरः. -ing, s. परि-,भ्रमणं-अटनं, विचरणं.

Row, v. t. (नौदंडेन) वह् c., प्रेर् c., संचल् c., प्रणुद् 10, प्रणुद् c. -v. i. नौकां वह् c. or प्रेर् c. &c. -s. राजिः, पंक्तिः, श्रेणिः-णी, आवलिः-ली, ततिः, माला, (all f.); *See* Line. 2 कलहः, संमर्दः, तुमुलरवः, कोलाहलः.

-er, s. नाविकः, पोतवाहः, क्षेपणिधरः, क्षेपणीधरः.

Rowdy, a. दुर्वृत्त. 2 कलहप्रिय.

Rowel, s. क्षेत्रकः.

Royal, a. राजकीय, राजयोग्य, राजार्ह, नृपोचित; राज-नृप in comp. -ist, s. राजपक्षीयः, राजपक्षावलंबिन् m. -ly, adv. राजवत्, नृपोचितं. -ty, s. राजत्वं, राजमहिमन् m., राजाधिकारः, नृपत्वं, प्रभुत्वं, आधिपत्यं, ऐश्वर्यं.

Rub, v. t. घृष् 1 P, मृद् 9 P or c. 2 प्र-परि-मृज् 2 P or c., प्रक्षल् 10, निज् 3 U, परिष्कृ, म्रक्षणीकृ 8 U. 3 चूर्ण् 10, पिष् 7 P, क्षुद् 7 P. 4 अभि-,अंज् 7 P, दिह् 2 U, लिप् 6 P, मृद् 5 (Feet) संवह् c., मृद्; 'r. together' संपिष्, संघट्; 'r. the teeth together' दंतैर्दंतान् घृष् or निष्पिष्; 'r. out' अप-व्या-मृज्, व्यामृश् 6 P or c., विलुप् c., उच्छिद् 7 P. -v. i. सं-घट्ट् 1 A, संघट्. 2 संघर्षेण अपचि-क्षि-pass. or अवसद् 1 P 3 कृच्छ्रेण सं-उत्-तॄ 1 P, अति-इ 2 P. -s. घर्षणं, अभ्यंजनं, संवाहनं, मर्दनं, &c. 2 संघट्टः, समाघातः, संमर्दः. 3 कृच्छ्रं, कष्टं; See Difficulty. -ber, s. घर्षकः, मार्जकः, मर्दकः. 2 (Substance) घर्षकः. -bing, s. घर्षणं, मर्दनं, &c.

Rubbish, s. अवस्करः, उच्छिष्टं, मलं, तुच्छ-निःसार-द्रव्यं.

Rubicund, a. आरक्त, पाटल.

Rubric, s. व्यवस्था, विधिः.

Ruby, s. माणिक्यं, पद्मरागः, शोणरत्नं, लोहितकः. -a. रक्त, पाटल, रक्तवर्ण.

Ruck, s. See Crease.

Rudder, s. कर्णः, नौकादंडः, अरित्रं, कर्णः.

Ruddy, a. रक्त, अरुण; See Red.

Rude, a. अविनीत, अविनय, विधात, धृष्ट, अमर्याद, उद्धत, सप्रतिभ, असभ्य, अशिष्ट, अनार्य, दुःशील, नष्टविनय, निर्लज्ज, प्रगल्भ. 2 असंस्कृत, अशिष्ट, ग्राम्य, अकृतविद्य, अप्रबुद्ध, अनक्षर, अशिक्षित, विद्याहीन-शून्य. 3 स्थूल, अश्लक्ष्ण, अनिपुण, अपटु, कर्कश. -ly, adv. अविनयेन, धृष्टवत्, प्रगल्भं, स्थूलं, अशिष्टतया, &c. -ness, s. अविनयः, वैयात्यं, धाष्टर्यं, अमर्यादा, प्रागल्भ्यं, प्रतिभा, अनार्यता, अदाक्षिण्यं. 2 असंस्कारः, अशिष्टता, ग्राम्यता. 3 स्थूलता, अदाक्ष्यं, &c.

Rudiment, s. उपक्रमः, प्रारंभः, मूलं, प्रथम-मूल-तत्त्वं; 'r. s of knowledge' ज्ञानतत्त्वानि, ज्ञानमूलं, उपक्रमणिका. 2 मूलांशं, बीजं, मूलं, मूलवस्तु-द्रव्यं. -al, -ary, a. प्राथमिक-मौलिक-(की f.), मूल-प्रथम-आदि in comp.

Rue, v. t. अनुशुच् 1 P, अनुतप् 4 A; See Repent, Regret, s. ब्राह्मी. -ful, -a. अनुशोकाकुल, अनुतापार्त, शोकार्त, विषण्ण, उद्विग्न.

Ruffian, s. आततायिन् m., साहसिकः, वधोद्यतः

Ruff, Ruffle, v. t. संकुच् 1 P, आकुंच् c., पुटीकृ 8 U, चूर्ण् 10; 'r. up' प्र-सं-क्षुभ् c., प्रकुप् c., व्याकुलीकृ, उद्विज् c.; 'not r. ed in disposition' प्रकृतिगंभीर, शांतात्मन्. -s. भंगि f., ऊर्मि f., पुटः, चूर्णः. 2 प्र-सं-वि-क्षोभः, प्रकोपः, व्याकुलत्वं, उद्वेगः, संभ्रमः, अशांति f. -ed, a. सं-,क्षुब्ध, क्षोभित, प्रकोपित, आकुल, व्याकुल, व्यग्र, अस्थिर, संभ्रांत, अशांत, उद्विग्न, कातर, पारिप्लव.

Rug, s. कंबलः, रल्लकः; आस्तरः-रणं.

Rugged, a. विषम, नतोन्नत. 2 रु(रू)क्ष, कर्कश; See Harsh. -ness, s. वैषम्य, कार्कश्यं.

Rugose, a. वलित.

Ruin, v. t. नश् c., वि-प्र-°, प्र-वि-ध्वंस् c., क्षि 5, 9 P or c., वि-,लुप् 6 P or c., उच्छिद् 7 P, हन् 2 P or c. (घातयति); उत्-अव-सद् c., नि-अव-पत् c., उद्-हृ 1 P, (building): 'r. a man' संपत्ति-विभव-नश् c., परिक्षीण-a. कृ. -s. वि-,नाशः, प्र-वि-ध्वंसः, क्षयः, लोपः, विघातः, उच्छेदः, अवसादः, निपातनं, उत्सन्नता, जीर्णता (of a house); 'in r. s' जीर्ण, विशीर्ण, उत्सन्न, जर्जर, जर्जरित. 2 अनिष्टं, अपायः, हानि f., क्षति f., अनर्थः. 3 (Of fortune) परिक्षयः, वित्त-विभव-नाशः, भाग्यक्षयः, ऐश्वर्यनाशः-भंगः-लोपः, परिक्षीणता; 'r. of an army' बलव्यसनं, भंगः, पराभवः, पराजयः; 'to go to r.' परिक्षि-pass., क्षयं-नाशं-या 2 P or -इ 2 P, प्र-वि-ली 4 A; ध्वंस् 1 A; 'r. seize thee' अजीवनिः ते भूयात्; See under Perdition. -ed, a. नष्ट, ध्वस्त, क्षीण; अवसन्न, उच्छिन्न, जीर्ण, विशीर्ण, जर्जर, &c. 2 परिक्षीण, नष्टविभव, गतश्रीक, नष्ट or गत-धन or ऐश्वर्य, प्रचलितविभव, क्षीणधन. -ous, a. उत्सन्न, क्षीण, जीर्ण &c. 2 वि-,नाशिन्, नाशावह, नाश-क्षय-कर (री f.), घातुक, अनिष्टोत्पादक. -ously, adv. सनाशं, सक्षयं, सापायं.

Rule, v. प्र-,शास् 2 P, नि-विनि-यम् 1 P, परिपा c. (पालयति), विनी 1 P, गुप् 1 P, ईश् 2 A (with gen.); अध्यास् 2 A, अधि-ष्ठा 1 P; तंत्र् 10; 'r. ing subjects like one's own children' प्रजाः प्रजाः स्वा इव तंत्रयित्वा (S. 5). 2 आदिश् 6 P, वि-धा 3 U, नियमं-विधिं-कृ 8 U, व्यव-स्था c. (स्थापयति); gen. ex. by (s.). 3 निग्रह् 9 P, सं-नि-यम्; See Control. 4

रेखादि: अंक् 10. —s. शासनं, अधिकारः, प्रभुत्वं, आधिपत्यं, स्वाम्यं, ईशत्वं, ऐश्वर्यं, पालयितृत्वं. 2 विधिः, नियमः, सूत्रं, व्यवस्था; (moral &c.) मर्यादा, क्रमः, निर्देशः, आनिदेशः, प्रयोगः-प्रथा, शासनं, मार्गः, कल्पः; तत्त्वं (of science); न्यायः 3 प्रमाणं, मानं; 'general r.' उत्सर्गः, सामान्यविधिः; 'r. of action' क्रियाविधिः-मार्गः, 'r. of judicature' व्यवहारविधिः-मार्गः; 'according to the r.' यथाविधि, विधिवत्; यथान्यायं; 'r. of three' त्रैराशिकं. —er, s. शासितृ m., पालयितृ m., शास्तृ m., शासकः, पालकः, अधिष्ठातृ m., अधिपतिः, अधीशः, नियंतृ m., स्वामिन् m., प्रभुः, ईश्वरः; 'under one r.' एकस्वामिक. 2 रेखालेखनी. —ing, a. शासत्, नियंतृ, पालक &c. 2 प्रबल, बलिष्ठ, प्रधान, बलिष्ठ; 'r. deity' अधिदेवता, अधिष्ठात्री देवता.

Rum, s. सीधु m. n., आसवः, मैरेयं. —a. असंगत, अपरूप.

Rumble, v. i. रट् 1 P, नद् 1 P, गर्ज् 1 P, गंभीरं स्वन् 1 P or घुष् 1 P. —ing, s. गर्जनं, नर्दनं, दीर्घ-गंभीर-नादः-ध्वनिः-घोषः, निर्घोषः (of clouds) स्तनितं, घनध्वनिः, मेघनादः, &c.

Ruminate, v. i. रोमंथायते (D.): रोमंथं अभ्यस् 4 U, (S. 2) 2 पुनः पुनः ध्यै 1 P or चिन्त् 10, नि-ध्यै desid. (निदिध्यासति). —ion, s. रोमंथः; अपरिश्रमचिंता, निदिध्यासनं. —Ruminant, a. रोमंथकर (री f.).

Rummage, v. t. अस्तव्यस्तीकृत्य सूक्ष्मं अन्विष् 4 P or मृग् 10.

Rumour, s. जनप्रवादः, किंवदंती, प्रवादः, जनश्रुति f., लोकवादः-वार्ता; *See* **Report.** —v. t. Ex. by (s.); 'it is r. ed' इति किंवदन्ती श्रूयते, इति जनप्रवादः.

Rump, s. *See* **Hip.**

Rumple, *See* **Fold.**

Run, v. i. धाव् 1 P, द्रु 1 P, प्र-वि-°, शीघ्रं-द्रुतं गम्-चल्-व्रज् 1 P or या-इ 2 P, रंह् 1 P (as a fluid) स्रु 1 P, प्र-स्यंद् 1 A, वह् 1 P, द्रु, प्र-स्रु; (as rivers) वह् 1 P, प्रवृत् 1 P, गम् (सागरं); 'how much has the night yet to r.' कियदवशिष्टं रजन्याः (S. 4) 3 प्र-वि-स्तॄ 4 A, दृश्, दृ. 4 प्रवृत् 1 A. प्रवृत्, प्रवृ; *See* **Proceed.** 5 अति-इ 2 P, अतिक्रम् 1 U. 4 P, या 2 P, गम्; *See* **Pass.** 6 (Away) प्र-,पलाय् 1 A, अपसृ 1 P, अपक्रम्; अपया-गम्-धाव्-सृ 1 P, प्र-वि-द्रु 7 (As a sore) पूयं स्रु c. or सुच् 6 P. 8 वितन्-विस्तृ pass.; व्यापृ; *See* **Extend**. 'r. to waste' परि-,क्षि pass. 'r. not' मर्यादां अति-इ or अतिक्रम् —v. t. धाव् c. चल् c., वह् c.
—about, इतस्ततो धाव्, वि-परि-धाव्. —after, अनुधाव-द्रु-धाव्-ष &c. —against, at, towards, अभि-प्रति-उप-धाव्-द्रु, संमुखं धाव्. —down, (v. t.) मुधाय् अवधाव् 1 P, अवसृ 9 P; *See* **Decry, Depreciate.** 2 **Chase,** q. v. —in, आ-प्र-विश् 6 P. —into, उप-गम्, आ-पद् 4 A, गम् pass.: 'run into debt' ऋणग्रस्तो भूत्. —off, अपसृ, अपक्रम्, अपया; 'till the brook has r. off' यावन्निर्झरस्रोतो नापगच्छति, न ... स्रवति, न क्षीयते. —on, (of water) ... 2 प्रवृत्, प्रवृ. 3 **Prate,** q. v. —out, क्षि-अवचि-pass., अवसो-अपाय् pass. —over, परिप्लु, उपरि द्रु; *See* **Overflow.** —up, वृध् 1 A: *See* **Increase.** —s. धावनं, द्रवणं, विद्रवः, पलायनं. 2 गति f.: क्रमः, मार्गः, प्रवृत्ति f. 3 प्रवाहः, स्रावः, प्र-नि-स्यंदः. 4 प्रचारः, प्रवृत्ति f.: प्रवर्तनं. 5 पर्ययः, परिणामः. 6 अन्ततः, अनुक्रमेण; 'in the long r.' अंते, दीर्घकालादूर्ध्वं; 'the ordinary r. of people' सामान्याः, पृथग्जनाः, प्राकृताः, साधारणजनाः. —ner, s. धावकः. 2 वार्तिकः, जंघाकारिकः, प्र-,वाहिन् m., ... m., त्वरितः, वेगिन् m., जवनः, जवः. —ing, s. *See* (s.). —a. धावत्, प्रवहत् &c. 2 प्रसृत, पूयस्राविन् (sore). 3 यथाक्रमं, आनुपूर्व्येण. —**Runaway, Runagate,** s. पलायितः, अपधावितः. 2 युद्धत्यागिन् m., रणविमुखः.

Rundle, s. सोपानं, आरोहणं.

Rung, s. संधि f., सोपानं, आरोहणं, पर्वन् n.

Rupture, s. भेदः, स्फोटनं, भंगः. 2 भेदः, कलहः, स्नेहभंगः-भेदः, सुहृद्भेदः. 3 अंत्रवृद्धि f. अंत्रः. —v. t. भंज् 7 P, भिद् 7 P, स्फुट् c.

Rural, a. ग्राम्य, जानपद (दी f.), ग्रामीण, ग्रामीय, ग्राम-जनपद, in comp.; 'r. pleasures' ग्रामवासवाचित्र्यं.

Ruse, s. *See* **Pretext.**

Rush, v. i. वेगेन-सत्वरं-धाव् 1 P or गम्-चल् चल् 1 P, सवेगं या 2 P or पत् 1 P; 'r. upon' आक्रम् 1 U, 4 P, अभि-पत-स्कंद् 1 P, सवेगं अभिद्रु or आपत्, अभिपत्; युद्धाभिलाषिणः सम्पतन्तः (U. 5) 'r. ing upon (me) for fighting' 'r. forth' निर्गम्, बहिर्गम्, निःसृ. 'r. headlong' अतिवेगेन-साहसपूर्वं-प्रविश् 6 P. —s. महावेगः, जवः, आवेगः, संरंभः. 2 अतिवेगेन धावनं-प्रपातः, सवेगाभिस्कंदः, सहसाक्रमः. 3 तृणं. 'I do not care a r.' तृणमात्रमपि नेक्षुकः. —light, s. तृणप्रकाशः, तृणालोकः;

Russet, a. कपिश, श्याव.

Rust, *s.* [illegible], [illegible], [illegible] ([illegible]) [illegible], [illegible]; [illegible]. —*v.* [illegible] 5 U. —**y**, *a.* [illegible], [illegible], [illegible], [illegible].

Rustic, *a.* [illegible], [illegible], [illegible] (ती *f.*), [illegible] (ती *f.*), [illegible], [illegible], [illegible] —*s.* [illegible], [illegible], [illegible], [illegible] —**ally**, *adv.* [illegible], [illegible]. —**ity**, *s.* [illegible], [illegible], [illegible].

Rusticate, *v. t.* निर्वस् *c.*, [illegible] *c.* —*v. i.* [illegible] 1 P.

Rustle, *v. i.* [illegible] कृ 8 U. —**ing**, *s.* [illegible], [illegible], [illegible].

Rut, *s.* [illegible], [illegible], [illegible]. 2 [illegible], [illegible]; "in r." [illegible] —**tish**, *a.* [illegible], [illegible].

Ruth, *s.* See **Pity**. —**less**, *a.* निर्दय, निर्घृण, क्रूर, निष्कृप; See **Cruel**.

Ryot, *s.* कृषक:, कर्षक:, कृषीवल:.

S

Sabbath (day), *s.* [illegible]-दिवस:.

Sable, *a.* श्याम, कृष्ण, कृष्णवर्ण. —*s.* [illegible]: 2 [illegible].

Sabot, *s.* काष्ठपादुका.

Sabre, *s.* [illegible], [illegible], [illegible]: कृपाण:

Sabulous, *a.* See **Sandy**.

Sac, *s.* See **Sack**.

Saccharine, *a.* शार्कर (री *f.*), [illegible] मधुर.

Sacerdotal, *a.* पौरोहित in comp., [illegible], पौरोहित (ती *f.*)

Sachel, *s.* [illegible]:, [illegible], [illegible]

Sachet, *s.* पुट:, कोष:

Sack, *s.* स्यूत: [illegible], स्यूत:, [illegible]-कोष:, [illegible]. 2 [illegible], [illegible], [illegible]; "s.-cloth" [illegible], [illegible], [illegible]. —*v. t.* लुंठ् 1 P., 10. [illegible] 1 A., [illegible] 1 P.

Sacrament, *s.* संस्कार:. —**al**, *a.* [illegible].

Sacred, *a.* पुण्य, पवित्र, परि-पूत, [illegible], शुचि. 2 [illegible] (की *f.*), (opposed to profane). 3 पूज्य, [illegible]; [illegible]. 4 [illegible], [illegible]. 5 [illegible], [illegible], [illegible]; [illegible], [illegible] (person): "an ambassador, being considered s., never tells an untruth" [illegible] (II. 3): "s. spot" [illegible]

[illegible], [illegible]; "s. grove" [illegible], [illegible]; "s. knowledge" [illegible], [illegible]; "s. writing" [illegible], [illegible], [illegible] *f.*

Sacrifice, *s.* यज्ञ:, [illegible], [illegible], [illegible], [illegible], [illegible], [illegible], [illegible], [illegible] *f.*, &c. in comp.; "horse-s." अश्वमेध:; "human s." [illegible] &c.; "imperial s." [illegible]; "fit for a s." यज्ञिय, [illegible]. 2 [illegible], [illegible], [illegible], [illegible]. 3 [illegible], [illegible], [illegible], [illegible], [illegible]; "even at the s. of one's life" [illegible], [illegible]; oft. by instr. alone ([illegible]) —*v. t.* [illegible] 1 U.; हु 3 U., [illegible] 1 P., [illegible] 2 P. or [illegible] 3 U., [illegible] 1 A. (animal): "he s. a beast to Rudra" [illegible]; "he s. ed a horse" [illegible], [illegible]. 2 [illegible] 1 P., [illegible] 6 P., [illegible] P., [illegible] ([illegible]), [illegible] 7 A., 10. "s. ing their own interests [illegible], "without s. ing their interests" [illegible] (Bh. [illegible]). —**er**, *s.* [illegible], [illegible], [illegible], [illegible], [illegible]. —**Sacrificial**, *a.* यज्ञिय, [illegible] ([illegible] *f.*), [illegible] in comp.; "s. work" [illegible]; "s. fire" [illegible], [illegible], [illegible], [illegible]; "s. priest" ऋत्विज् *m.*; See **Priest**; "s. vessel" [illegible].

Sacrilege, *s.* [illegible], [illegible], [illegible], [illegible]. —**Sacrilegious**, *a.* [illegible], [illegible].

Sad, *a.* विषण्ण, म्लान, [illegible], [illegible], [illegible], उद्विग्न, [illegible], [illegible], [illegible], दुर्मनस्, विमनस्. 2 [illegible], [illegible], [illegible] ([illegible] *f.*), [illegible]. 3 [illegible]; See **Grave**; "to be s." [illegible], [illegible] 1 P., [illegible] 1 P., [illegible] (D). —**den**, *v. t.* [illegible] 8 U., [illegible] *c.*, [illegible] *c.*; See **Grieve**. —**ly**, *adv.* [illegible], [illegible], [illegible], [illegible], [illegible]. —**ness**, *s.* [illegible], [illegible], [illegible], [illegible], [illegible] *f.*, [illegible].

Saddle, *s.* [illegible], [illegible], [illegible]. —*v. t.* [illegible] *c.* or [illegible] *c.*, [illegible] 8 U.; "mounting the s. ed Indrayudha" [illegible] (K. 196) (fig.) [illegible] 3 U. or [illegible] 4 U.; "s.-horse" [illegible]. —**er**, *s.* [illegible].

Safe, *a.* [illegible], [illegible], [illegible], [illegible], [illegible], निर्भय, [illegible]. 2 [illegible], [illegible], [illegible], [illegible], [illegible], [illegible]. 3 [illegible], [illegible], [illegible]; "s. against

enemies ' दुरासदः परैः (R. VIII. 4.). 4 क्षेम्य, भयरहित, क्षेम, निर्भय; ' a s. place ' निर्भयस्थानं, अभयहेतुकं स्थलं; ' sound and s. ' कुशलिन्, निरामय, सुस्थ, अक्षत. -s. लोहपेटिका, लोहमंजूषा; ' s. conduct' अभयप्रदानं-पत्रं; ' s.-guard ' रक्षा, गुप्ति f., रक्षणं; **Pass,** q. v. **-ly,** *adv*. क्षेमेण, निराबाधं, अक्षतं, सक्षेमं, निर्भयं; ' when she is s. brought to bed ' यदा अनघप्रसवा भवति (S. 4). **-ty,** *s*. क्षेमः-मं, स्वास्थ्यं, क्षेमता, अक्षतं, कुशलं, अनामयं. 2 रक्षा-क्षणं, निर्भयत्वं, अभयं, निर्भयं, भयआपद्-मुक्ति f.; ' to promise s. ' अभयवचनं दा 3 U.

Safflower, *s*. कुसुंभं, वह्निशिखं, महारजनं, कमलोत्तरं.

Saffron, *s*. कुंकुमं, अग्निशिखं, वरं, बाह्लि-(ह्ली)कं, पीतनं, रक्तं, संकोचं, पिशुनं, धीरं, लोहितचंदनं, काश्मीरजन्म. **-a.** कुंकुमवर्णराग, अरुण; ' dyed with s. ' कुंकुमाक्त.

Sag, *v. i*. अव-नम् 1 P.

Sagacious, *a*. चतुर, विदग्ध, दूरदृष्टि, मेधाविन्, सूक्ष्मधी, तीक्ष्ण or कुशाग्र-मति or बुद्धि. **-ly,** *adv*. चतुरं, सूक्ष्मधिया, विदग्धतया. **-Sagacity,** *s*. वैदग्ध्यं, चातुर्य, तीक्ष्णमतित्वं, सूक्ष्मधीः-मति f.

Sage, *s*. प्र(प्रा)ज्ञः, विपश्चित् *m*., तत्त्वविद् *m*., बुधः, पंडितः, ज्ञानिन् *m*. 2 ऋषिः, मुनिः. 3 सिद्धः, साधुः, यतिः, सिद्धजनः-पुरुषः, आत्मज्ञः, मुमुक्षुः, ब्रह्मज्ञः. **-a.** प्राज्ञ, पंडित, ज्ञानिन्; *See* **Wise. -ly,** *adv*. पंडितवत्. **-ness,** *s*. प्राज्ञता, पांडित्यं.

Sagittarius, *s*. धनुः, धनूराशिः.

Sail, *s*. वातवस्त्रं-वसनं, नौवसनं-वस्त्रं; ' set s. नावं-पोतं-मुच् 6 P or चल् c. **-v. i.** (Of a boat &c.) वायुना नुद्-चुद्-वह्-प्रेर् -pass. 2 (Of persons) पोतमारुह्य or अध्यास्य प्र-स्था 1 A: नावा or पोतेन गम् or चल् 1 P, नावा तॄ 1 P or प्लु 1 A. जलवर्त्मना गम्-या &c. 3 चल्, सं-वि-सृप् 1 P; 's ing in the air ' विहायसा-नभोवर्त्मना-गच्छन्, नभसि संसर्पन्. **-ing,** *s*. समुद्रयानं. **-or,** *s*. नाविकः, पोतवाहः, नौवाहः, समुद्रगः.

Saint, *s*. मुनिः, साधुः, सिद्धः, सिद्धजनः, ऋषिः, पुण्यजनः; *See* **Sage. -ly,** *a*. विमल, पवित्र, पुण्यात्मन्, परिपूत, अतिपुण्य, सिद्धतुल्य.

Sake, *s*. कारणं, निमित्तं, हेतुः, प्रयोजनं; ' for the s. of ' अर्थे or अर्थं in comp., हेतोः, निमित्तं, कारणात्, with gen. or in comp., कृते (with gen.); *See* **For.**

Sal, *s*. सालः, श्यालः, सर्जः, कार्श्यः, अश्वकर्णकः, सस्यसंवरः.

Salacious, *a*. *See* **Lustful.**

Salary, *s*. वेतनं, वृत्ति f., भृति f., मूल्यं; *See* **Hire,** 'monthly s.' मासिकं; 'annual s.' वार्षिकं. **-ied,** *a*. वृत्ति-वेतन-युक्त, कृतवेतन.

Sale, *s*. *See* under **Sell.**

Salient, *a*. प्रलंब, प्रोच्छ्रित. 2 प्लवग, प्लुतगामिन्. 3 (fig.) मुख्य, प्रधान, विशिष्ट, पुरःस्फुरत्.

Saline, *a*. लवण, क्षार, लवणगुणविशिष्ट; ' s. taste ' लवणरसः; ' s. soil ' ऊषः, क्षारमृत्तिका; ' having s. soil ' ऊषर, ऊषवत् **-a,** *s*. लवणक्षेत्रं.

Saliva, *s*. लाला, सृणि(णी)का, स्यंदिनी ' his mouth emits s. ' वक्त्रं लालायते. **-Salivary, -Salival,** *a*. लालास्राविन्. **-Salivate,** *v. t*. लालां स्रु c. or निःसृ c.

Sallow, *a*. आपीत, पांडुर, विवर्ण; *See* **Pale.**

Sally, *v. i*. निर्गम् 1 P, निष्पत् 1 P, निष्क्रम् 1 U, 4 P, जवेन बहिर्गम्, अभ्यव-स्कंद् 1 P, अभ्या-सद् c. **-s.** निर्गमः, निष्क्रमः-मणं, निःसरणं, आपातः, अभ्यासादनं, अभ्यवस्कंदनं, अवपातः. 2 स्फुरणं, उत्प्लवनं, उत्पतनं. 3 विलासः, विलसितं, विभ्रमः; ' s. es of wit ' बुद्धिविलासाः, विदग्धालापाः, नर्मालापविभ्रमाः; ' s. of levity ' बुद्धिचापल्यं-चांचल्यं; ' s.-port ' निर्गमद्वारं.

Saloon, *s*. (सुप्रसाधित-) शाला, कोष्ठः.

Salt, *s*. लवणं; (fig.) पिंडः; सफलीकृतभर्तृपिंडः (M. 5) ' who showed that he had not eaten his master's s. in vain '; ' rock-s. ' सैंधवः-वं, शीतशिवं; *See* under **Rock;** ' sea-s. ' अक्षी(क्षि)वं, वशि(सि)रं; ' black s. ' पाक्यः, विडं; क्षारं; ' sambhar s. ' रौमकं, वसुकं; ' sochal s. ' सौवर्चलः, अक्षं, रुचकं; ' s.-pan ' लवणक्षेत्रं;'s.-petro' यवजः,यवक्षारः,पाक्यः; यवाग्रजः. **-a.** लवण or क्षार-युक्त or मय (यी f.); लवणगुणविशिष्ट, क्षारधर्मक, लवणक्षार in comp. **-v. t.** लवणीकृ 8 U, लवणेन सिच् 6 P or अंज् 7 P. **-ed,** *a*. लवणाक्त, लवणसंसृष्ट, लवणित. **-ish,** *a*. ईषल्लवण. **-ness,** *s*. लवणत्वं, क्षारता.

Saltant, *a*. उत्पतत्, नृत्यत्.

Salubrious, *a*. हित-स्वास्थ्य-कर (रि f.), आरोग्यावह, पथ्य, अनामयकर, क्षेम्य, पुष्टिद, हित. 2 **Salutary,** q. v.

Salutary, *a*. हित, हित-कल्याण-कर (रि f.), -आवह, उपकारिन्, श्रेयस्कर, शुभंकर. 2 पथ्य; *See* **Salubrious.**

Salute, *v. t*. अभि-,वंद् 1 A, अभिवद् 10 A, प्रणिपत् 1 P, प्रणम् 1 P, नमस्कृ 8 U, नमस्यति (D.), सभाज् 10; अभिनंद् 1 P, उपस्था 1 A; 's. in return' प्रतिनंद्, प्रत्यभिनंद् 2 **Kiss,** q. v. **-s., -ation.** *s*. प्रणामः, प्रणति f., प्रणिपातः, अभि-,वंदनं, अभिवादः-दनं, नमस्कारः, नमस्क्रिया, सभाजनं; ' a s to

thee' भवन्तमुद्दिश्य. -er, s. अभिवादकः, अभिवन्दकः.

Salvage, s. सं-,उद्धृतं; उद्धारः, निस्तरणं.

Salvation, s. तारणं, उद्धारः, मुक्ति f., मोक्षः, निस्तारः, पापमुक्तिः, ऊर्ध्व-परम-गति f. 2 (Generally) परि-,त्राणं, रक्षणं, रक्षा; 'devotional way of s.' भक्तिमार्गः.

Salve, s. अंजनं, प्र-अनु-लेपः, उपदेहः. -v. t. अंज् 7 P. 2 उद्धृ 1 P. 3 शम् c. 4 निस्तॄ c.

Salver, s. रजतभाजनं, रूप्यपात्रं.

Salvo, s. *See* **Excuse.**

Same, a. तद् (*pron. a.*) with or without एव; अभिन्न, निर्विशेष, अनन्य; सम, समान, तुल्य; *See* **Like;** 'it is the s. Vâsanti' सैव वासंती; ते एव पादपाः; तदेव वर्म &c.:(U. 3); gen. by एक, स, सम, समान in comp.; 'of the s. family' सगोत्र; 'sitting in the s. car' एकरथसमास्थितौ; 'of the s. age' समवयस्क; एकरूप, समानजाति, सोदर &c.; 'at the s. time' एकदैव, युगपत्, एक-सम-काले, सर्मं, यौगपद्येन; 'in the s. way' तद्वत्, तथैव, तथा, एवं; 'he is the s. as a father to me' मां प्रति स पितृस्थाने-भूमौ वर्तते, पितृनिर्विशेषः. -ness, s. ऐक्यं, साम्यं, एकरूपत्वं, सादृश्यं, संवादः, अभेदः, समभावः; 's. of class' सवर्णता, सावर्ण्यं, एकवर्णता.

Sample, s. आदर्शः, प्रतिमा, प्रतिरूपं. -**Sampler,** s. सूचिकर्मादर्शः.

Sanable, a. साध्य.

Sanative, Sanatory, a. स्वास्थ्यकारिन्, रोगघ्न (घ्नी f.), रोगापह.

Sanctify, v. t. पवित्रीकृ 8 U, पुण्यीकृ, पापमलं हृ 1 P or अल् 10, परि-,पू 9 U, शुध् c., शुचीकृ, पापं-कल्मषं-निर्धू 5, 9 U, 6 P. 2 अनुमंत्र् 10 A, पुण्यकर्मणि विनियुज् 7 A, 10 or निक्षिप् 6 P. -ication, s. पापहरणं-नाशनं, पवित्रीकरणं. 2 -**Sanctitude, Sanctity,** q. v. -ing, a. शोधक, पावन. -**Sanctity,** s. निर्मलता, पवित्रता, पुण्यता, वि-, शुद्धि f., पाप or कल्मष-नाशनं or हरणं, अंतः शुद्धिः शौचं. 2 अलंघनीयता.

Sanctimony, s. दंभः, धर्माभिमानः, पुण्यवेषधारणं; बकवृत्ति f. -ious, a. दांभिन्, दांभिक (की f.), पवित्रंमन्य, बकवृत्ति, धर्माभिमानिन्, कपटधर्मिन्.-iousness, s. दंभः; *See* (s.).

Sanction, v. t. अनु-ज्ञा 9 U, अनुमन् 4 A, अनुमुद् 1 A; अनुशास् 2 P, आदिश् 6 P; प्रमाणीकृ 8 U, दृढीकृ, सत्यापयति-द्रढयति (D.), सत्याकृ. -s. अनुज्ञा, अनुमति f., अनुशासनं, अनुमोदनं, प्रामाण्यं, प्रमाणं, दृढीकरणं, सत्यापनं.

Sanctuary, s. शरणं, आश्रय-शरण-स्थानं. 2 पुण्यालयः, देवतागारं, पुण्य-पवित्र-स्थानं. 3 गर्भः, गर्भागारं, गर्भगृहं.

Sand, s. वालुका, सिकताः (pl.); 's.-bank' पुलिनं, सैकतं; 's.-glass' वालुकायंत्रं. -v. t. सिकताभिः आवृ 5 U or आकृ 6 P. -y, a. वालुकामय (यी f.), वालुकाकीर्ण, सिकतिल, सैकत (ती f.), बहुसिकत; 's. desert' मरुः, धन्वन् m. 2 वालुकानिभ; (fig.) अस्थिर, भंगुर, क्षणस्थायिन्, अदृढ.

Sandal, s. चंदनः (tree), चंदनं (wood) गंधसारः, मलयजः, भद्रश्रीः; 'white s. wood' तैलपर्णिकं; 'red s.' रक्तचंदनं, तिलपर्णी, पत्रांगं, रंजनं, कुचंदनं. 2 कोशी-षी, पादुका.

Sanders, s. (Yellow) पीतद्रुमः, कालीयकः, हरिद्रुः, दार्वी, पचंपचा, दारुहरिद्रा, पर्जनी. 2 (Red) *See* 'red sandal' under **Sandal.**

Sane, a. सुस्थ, निरामय, स्वस्थ, प्रकृतिस्थ, कल्य. 2 (In mind) अनुन्मत्त, प्रकृतिस्थ, अनातुल, अनुपहतचित्त, अविप्लुत, अविक्षिप्तचित्त. -ity,-ness, s. स्वास्थ्यं, अनुन्मादः.

Sang froid, s. प्रशांति f., निर्विकारता, प्रसादः, असंभ्रमः.

Sanguiferous, a. असृग्वाहिन्.

Sanguinary, a. (Of person) रक्त-रुधिर-प्रिय, जिघांसु, मारात्मक, क्रूरचित्त, निष्ठुरचेतस्. 2 रुधिरपातदूषित, रक्तस्रावयुत, बहुरक्त.

Sanguine, a. गाढ, उत्कट; *See* **Intense;** चंड, तीक्ष्ण, चंड-तीक्ष्ण-स्वभाव. 2 (Of persons) आशावत्, सुप्रत्याशिन्, अत्याशान्वित, दृढप्रत्यय, जातविश्वास; 'I feel quite s. that' इति मे गाढाशंसा; 's. hope' सुप्रत्याशा, गाढाशंसा, उत्कटेच्छा. -ness, s. अत्याशा, अत्याशंसा, &c.

Sanies, s पूयं; *See* **Pus.** -**Sanious,** a. पूयस्राविन्.

Sanitary, a. स्वास्थ्यहित, स्वास्थ्य in comp., आरोग्यकर (री f.), आरोग्यावह.

Sap, s. सारः, रसः, द्रवः, सत्त्वं, निर्यासः. -v. t. उत्खन् 1 P, समूलं उच्छिद् 7 P or भ्रंश् c. -per, s. खनकः, सौरंगिकः. -less, a असार, निःसार, विरस, नीरस, निःसत्त्व -py, a. रसाढ्य, सरस, आर्द्र, ससत्त्व, रसवत्. -**Sapid,** a. सुरस, मिष्ट, स्वादु.

Sapling, s. बालवृक्षः, वृक्षकः.

Sapient, a. प्राज्ञ, प्रज्ञ, ज्ञानपूर्ण; *See* **Wise.**

Saponaceous, a. चिक्कण, मेदुर.

Sapor s. *See* **Flavour.**

Sapphire, s. महानीलः; इंद्रनीलः, नीलः, नीलोपलः.

Sarcasm, s. अव-आ-क्षेपः, निंदागर्भं वचः, परिभाषणं, सनिंद उपालंभः; कटुः उपहासः. -**Sarcastic,-al,** a. साक्षेप, निंदागर्भ, अर्धतुद, उग्र, कटु, तीक्ष्ण, सावहास, परिभाषिन्, सोपालंभ. -ally, adv. साक्षेपं, सोपालंभं.

Sarcasm, *s.* *See* **Taunt**.

Sarcophagous, *a.* मांसाशीन, मांसभुज्.

Sardonic, *a.* निठुर, कराल.

Sardonyx, *s.* गोमेद-मणिः.

Sartor, *s.* सूचिकारः. **-ial**, *a.* सू(सौ)चिकसंबंधिन्.

Sash, *s.* (कटिबंधार्थं) परिकरः, मेखला, कटिसूत्रं. 2 वातायनचक्र.

Satan, *s.* पिशाचस्वामी, पिशाचनायकः. **-ic**, *a.* पैशाच (ची *f.*).

Satchel, *s.* *See* **Sachel**.

Sate, *See* **Satiate**.

Satellite, *s.* उपग्रहः. 2 (लाक्ष.) पार्श्वचरः, अनुयायिन् *m.*, अनुगामी; नित्यपार्श्ववर्ती.

Satiate, *v. t.* सं-परि-तृप् 5 P or *c.*, अत्यंतं तृप् *c.*, अतितृप्तिं-सौहित्यं-उत्पद् *c.*, परिपूर् 10. **-ed**, *a.* अतितृप्त, परिपूर्णकाम, पर्याप्तकाम, संतर्पित, सं-परि-तृप्त; तृषित; 'to be s.' सं-परि-तृप् 4 P or तृप् 4 P. **-Satiety**, *s.* तृप्ति *f.*, तर्पणं, सौहित्यं, अतितृप्ति *f.*, सौहित्य-तृप्तिः; पूर्णकामता, तृप्तता, परितृप्ति *f.*

Satin, *s.* चीनांशुकं (*s.*-cloth).

Satire, *s.* आक्षेपगर्भं कवितं, उपहास-कविता. 2 **Sarcasm**, *q. v.* **-ical**, *a.* उपहासात्मक, सोपहास, साधिक्षेप; *See* **Sarcastic**. **-ist**, *s.* आक्षेपकविन् *m.*. **-ize**, *v. t.* साक्षेपं वर्ण् 10, अवमं 1 P, काव्यद्वारा आ-अधि-क्षिप् 6 P.

Satisfy, *v. t.* (Persons) सं-परि-तृप् *c.*, तुष् *c.*, सर्वं-इच्छां-पूर् 10 or निर्वृत् *c.*, तुष्टिं-तुष्टिं-उत्पद् *c.*, तुष्यति (D.), प्री 9 P, आराध् *c.*; सांत्व् 10, प्रसद् *c.* (hunger, desire, &c.) शम् *c.* (शमयति), प्र-उप-शम् *c.*, छिद् 7 P, परि-पूर्, निराकृ 8 U, निर्वृत् *c.*; 'child, s. your curiosity' पुत्रक कुतूहलं पत्ताः (U. 4). 2 संदेहं अपनी 1 P, संशयं छिद् or हृ 1 P or निरस् 4 U, निष्पारीकृ. **-action**, *s.* सं-परि-तोषः, तुष्टि *f.*, पर्याप्ति *f.*, इच्छापूर्ति *f.*, सौहित्यं, कामपूरणा-तृप्तिः-निवृत्तिः-शांतिः *f.* 2 शांतिः, शमनं, निराकरणं, परि-हरणं, छेदः, निवृत्तिः, पूर्तिः, दर्शनं. 3 संशयच्छेदः, संदेहनिवृत्तिः-परिहारः. 4 प्रतिकर्तृ, निस्तारः, शुद्धि *f.* **-ed**, *a.* तुष्ट, हृष्ट, संतुष्ट, तर्पित, पूर्ण-निवृत्त-काम, पर्याप्तकाम, प्रीत, कृतिन्, कृतार्थ, चरितार्थ. 2 छिन्न, पूर्ण, शांत, निवृत्त. 3 छिन्नसंशय, हतनिरस्त-संदेह; 'to be -' तुष्-तृप् 4 P, प्री pass. **-ing**, *a.* संतर्पक, संतोषक, तुष्टि-तृप्तिकर (री *f.*), संशयच्छेदक. **-Satisfactory**, *a.* युक्त, समर्थ, (समर्थयुक्ततरं), पर्याप्त, संशयच्छेद, संदेहच्छेदिन्. 2 तुष्टिप्रद, संतोष-तृप्ति-तुष्टि-कर. 3 (Atoning) Ex. by प्रमृज् 2 P, निष्कृ *c.*; *See* **Atone**. **-ily**, *adv.* सम्यक्तया, पैयेतन संशयच्छेदित्वया, सम्यक्.

Satrap, *s.* मांडलिकः, मांडपतिः.

Saturate, *v. t.* आर्द्रीकृ 10, आ-परि-प्लु, नि-सिच् 6 P, आर्द्रीकृ *c.* **-ed**, *a.* अतिसिक्त, परिपूर्ण; *See* **Impregnate**. **-ion**, *s.* अतिसेक-क्लेदः, परिपूर्णत्व.

Saturday, *s.* शनि-मंद-वासरः.

Saturn, *s.* शनिः, शनैश्चरः, पंगुः, सौरिः. **-Saturnine**, *a.* मंद, जड-मंद-शीलप्रकृति, जडस्वभाव. **-Saturnalia**, *s.* शनिमहोत्सवः.

Satyr, *s.* वनदेवता, वन-अरण्य-चरः.

Sauce, *s.* सूपः, तेमनं, निष्ठानं; उपसेचनं, व्यंजनं, उपस्करः; 's.-pan' उखा, पिठरः; *See* **Frying-pan**. **-Saucer**, *s.* शरावः, चषकः, आधारः.

Saucy, *a.* धृष्ट, निर्लज्ज, निर्लज्ज, प्रगल्भ, अविनीत; सावलेप. **-ily**, *adv.* अविनयेन, धृष्टवत्. **-iness**, *s.* अविनयः, धार्ष्ट्यं, प्रतिकमानं.

Saunter, *v. i.* मंदं मंदं परिक्रम् 1 U, 4 P or भ्रम् 1, 4 P, शनैः शनैः विचर् 1 P. **-ing**, *s.* मंदं परिक्रमणं.

Savage, *a.* वन्य, जांगल (ली *f.*), आरण्यक, वन-अरण्य in comp. 2 असभ्य, अशिष्ट, अविनीत, असंस्कृत, आचारहीन, अनाचार. 3 क्रूर, हिंस्र, निष्ठुर, निर्दय, दारुण, करकर्मन्, श्वापद (दी *f.*): 'all of man is s.' पुरुषा नाम निष्ठुराः (Mr. 5.). **-s.** अशिष्ट-असभ्यजनः. 2 कुकर्मन् *m.*, राक्षसः, दैत्यः, नरपशुः. 3 म्लेच्छः, किरातः, शबरः, यवनः, भिल्लः &c. **-ly**, *adv.* अशिष्टवत्, निष्ठुरं. **-ness**, *s.* अशिष्टता, क्रौर्यं, क्रूरता, &c.

Savant, *s.* बुधजनः, पंडितः, विद्वज्जनः; *See* **Learned**.

Save, *v. t.* रक्ष् 1 P, in all senses, परि-, त्रै 1 A, उद्-समुद्-हृ 1 P, मु 1 P, तॄ *c.*, उत्-सं-नि-, मुच् *c.*, मोक्ष् 10, त्राणाद् मुच् &c. 2 सं-चि 5 U, संचय, नि-धा 3 U, संग्रह् 9 P, अवशिष् *c.* 3 निवृत् *c.*, चिवृ *c.*, निरुध् 7 U, वारिध्; 'those that were s.-ed out of the slain' हतशेषाः, हतावशिष्टाः. **-prep.** विहाय, मुक्त्वा, वर्जयित्वा; *See* **Except**. **-ing**, *a.* अल्पव्ययशील, अल्पव्ययिन्, मितव्यय, अनुकरस्त. 2 उद्धारक, मुक्तिप्रदायिन्, मोक्षद. 3 निवर्तक, निवारक-हेतुः. **-s.** रक्षणं, संचयः, संग्रहः, निधानं. 2 संचित-रक्षित-धनं, संचयः. **-Saviour**, *s.* तारकः, त्रायकः, परि-त्रातृ *m.* रक्षिता, उद्धर्ता, उद्धारकः.

Savour, *s.* स्वादः, रसः, रुचि *f.* 2 गंधः, वासः. **-v. i.** स्वादी-गंधी-भू 1 P. 2 (Appear like) Ex. by कल्प, प्राय in comp., दृश् pass. with abl.; by आ-भास् 1 A; 'it s.-s of falsehood' इदं असत्यप्रायं, अनृतमयं, असत्यकल्पं, असत्यप्रकारकं.

-y, *a*. सरस, सुरस, स्वादु; मिष्ट, रसवत्, रुचिकर. 2 सुरभि, सुगंधि.

Saw, *s*. करपत्रं, ककचः-चं, पत्रदारणः. -*v. t.* क्रकचेन वद् 10 or दृ 9 P or c. or छिद् 7 P or अवकृत् 6 P; 's.-dust' काष्ठविदलं; 's.-pit' काष्ठविपाटनमार्गः. -**Sawyer**, *s*. क्राकचिकः, दारुदारणः.

Say, *v. t.* वद्-गद्-भण् 1 P, वच् 2 P, ब्रू 2 U, भाष् 1 A, उदा-व्या-हृ 1 P; उच्चर् c., उदीर् c., आलप् 1 P (words &c.): मंत्र् 10 A; (tell) कथ् 10, आचक्ष् 2 A, आ-,शंस् 1 P, अभि-धा 3 U, आ-ख्या; *See* **Tell**; 'I say' ननु भणामि, ननु ब्रवीमि, ननु simply; (ननु पदे परिवृत्य भण Mr. 5); 'they s.' ex. by किंवदंती, जनप्रवादः, इति श्रूयते; *See* **Report**; 'that is to s.' ex. by नाम. -**ing**, *s*. वचनं, वाक्यं, वचस् *n*., उक्तं, &c.; भाषितं, भाषणं, उक्ति *f*., भणितं. 2 आभाणकः, प्रवादः; 'popular s.' जनप्रवादः; 'so runs the popular s.' तथा च लौकिकानामाभाणकः; *See* **Proverb**.

Scab, *s*. कच्छु-च्छू *f*., पामन् *f*., पामा; *See* **Itch**; (white eruption) सिध्मं, किलासं. 2 अधमजनः, नरापसदः, हीनः, अपकृष्टः. -**by**, *a* कच्छुर, वामन, सिध्मल. -**ies**, *See* (s. 1)

Scabbard, *s*. कोशः-षः, पिधानं, आधारः.

Scabrous, *a*. विषमतल, असमपृष्ठ

Scaffold, *s*. मंचः, इंद्रकोषः. 2 प्रेक्षामंचः. 3 वध्यशिला-स्थानं-काष्ठं, घातस्थानं. -**ing**, *s* मंचः.

Scald, *v. t.* तप्तजलादिना दह् 1 P. -*s*. दाहः.

Scale, *s*. तुला, धटः, तुलायंत्रं; 's.-pan' शिक्यं, पार्श्वः. 'goldsmith's s.' एषणी-णिका, नाराची. 2 (Of fishes &c.) वल्कः-ल्कं, वल्कलः-लं, शल्कं. शल्कलं;कवचः-चं. 3 फलकः-कं, पत्रं. 4 नि(निः)श्रेणी, अधिरोहि-(ह)णी, सोपानपद्धति *f*.-परंपरा. 5 श्रेणी, परंपरा, आवलि-ली *f*., माला, पंक्ति *f*. 6 प्रमाणं, परिमाणं; 'on a large scale' स्थूल-परिमाणेन. 7 (In music) ग्रामः. -*v. t.* आ-अधि-रुह् 1 P, आ-अधि-क्रम् 1 U. 4 P, लंघ् 1 A,10, अवस्कंद् 1 P. 2 वल्कं निष्कुष् 1 P or निर्हृ 1 P. -**y**, *a*. सशल्क, वल्कावृत; सवल्क, शल्किन, वल्किन.

Scalene, *a*. विषमत्रिभुज.

Scall, *s*. *See* **Scab**, **Itch**.

Scalp, *s*.मस्तकत्वच् *f*., शिरोग्रत्वच्,शिरोस्थि-चर्मन् *n*. -*v. t.* मस्तकत्वचं अवच्छिद् 7 P or निर्हृ 1 P.

Scalpel, *s*. लघुच्छुरिका.

Scamp, *s*. *See* **Rascal**.

Scamper, *v. i.* वि-द्रु 1 P, अवेग-वेगात्-द्रु or धाव् 1 P or पलाय् 1 A, सवेगं गम् 1 P.

Scan, *v. t.* निपुणं-सूक्ष्मं-निरूप् 10 or निरीक्ष् 1 A or अवलोक् 1 A, 10. 2 (Verses) मात्राः-गणान्-गण् 10 or विभज् 1 U.-**Scansion**, *s*. गण or मात्रा-गणनं or विभागः.

Scandal, *s*. निर्वादः, परि(री)वादः, अपवादः, असूया,अवर्णः, दुर्वर्णः,कौलीनं, आक्षेपः, उपक्रोशः, जुगुप्सा, कुत्सा, निंदा, वाच्यं; वाच्यता, गर्हणं-णा, पैशुन्यं, पिशुनवाक्यं. 2 कलंकः, दूषणं,अपमान-अपकीर्ति-हेतुः. -**ize**, *v. t.* (s.) with प्रकाश् c., अप-परि-वद् 1 A, परि-अप्-भाष् 1 A; *See* **Libel**. 2 **Offend**, q. v. -**ous**, *a*. परि-अप-वादक, आक्षेपगर्भ, परिवादात्मक, असूयक, (s.) in comp. 2 गर्हित, निंद्य,कलंककर-अकीर्तिकर-(री *f*.), दूषणीय, कुत्सित. 3 बीभत्स, घृणावह. -**ously**, *adv*. गर्ह्यं, कुत्सितं.

Scant, Scanty, *a*. अपर्याप्त, अप्रचुर, स्वल्प, अविपुल, न्यून, अबहुल, अभूयिष्ठ. 2 संबाध, अविस्तीर्ण, संकट; *See* **Narrow**. 3 **Miserly**, q. v. -**ly**, *adv*. अपर्याप्तं,स्वल्पं, अप्रचुरं, अल्पमात्रं, स्तोकं. -**ness**, *s*. अप्राचुर्यं, अपर्याप्ति *f*.,स्वल्पता.

Scantling, *s*. काष्ठखंडं.

Scape-Goat, *s*. बलिः.

Scar, *s*. किणः, अंकः, चिह्नं, क्षतचिह्नं, क्षतांकः, व्रणः-णं, क्षतं; (fig.) कलंकः. -*v. t.* क्षतेन-किणेन अंक् 10. -**red**, *a*. क्षतांकित, किणांक.

Scaramouch, *s*. भंडः, वैहासिकः.

Scarce, *a*. अबहुल, अप्रचुर, अप्रभूत, अपर्याप्त, अविपुल, न्यून, अभूयिष्ठ, स्वल्प. 2 विरल, दुर्लभ, दुष्प्राप, असुलभ; *See* **Rare**. -**ly**, *adv*. कष्टेन, कथमपि, कृच्छ्रेण, दुःखेन, सकृच्छ्रं, आयासेन, दुर् pr.; oft. by (*a.*); 'one s. gets a good son' दुर्लभो गुणवान् पुत्रः; by न, स्तोकं, 's. touches (walks on) the ground' स्तोकमुर्व्यां प्रयाति (S. 1); 's. a day passed' नैकमपि दिनं व्यतीतं; 's.-when' ex. by एव with loc. abs.; मात्र affixed to *adj*., or यावत्-तावत्; उपस्थितेयं कल्याणी नाम्नि कीर्तिते एव (R. I. 87); प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपप्लवानि नः कर्माणि संवृत्तानि (S. 3); एकस्य दुःखस्य न यावदंतं गच्छामि तावद् द्वितीयं समुपस्थितं (P. II. 6), oft. by च-च; आपूर्यश्च कलाभिरिंदुरमलो यातश्च राहोर्मुख &c. (Mal. 9). -**ity,-ness**, *s*. दुर्लभता, दुष्प्रापता, विरलता, अप्राचुर्यं, अपर्याप्ति *f*., स्वल्पता, न्यूनता, अबाहुल्यं, &c. 2 दुर्भिक्षं, अभावः, दुष्कालः, प्रयामः, नीवाकः.

Scare, *v. t.* त्रस् c., सं-वि-,° भी c., उद्विज् c.; 's. away' भयदर्शनेन वि-द्रु c. 's.-crow' विभीषिका, संत्रासनं, भयहेतुः.

Scarf, *s*. चेलकः, निचयः; उत्तरीयं, चेलं; 's.-skin' बाह्यत्वच् *f*.-चर्मन् *n*.

Scarify, *v. t.* त्वचं-चर्म-उल्लिख् 6 P or छिद् 7 P. **-ication,** *s.* त्वगुल्लिखनं, चर्मच्छेदः.

Scarlet, *a.* शोण, अरुण, सिंदुरवर्ण; 's. fever' उदर्दः.

Scarp, *s.* लंबः. **-v.** *t.* लंबरूपेण निकृत् 6 P.

Scate, *See* **Skate.**

Scath, Scathe, *v. t.* क्षण् 8 P, अर्द् 1 P or c.; *See* **Harm, Injure. -less,** *a.* अक्षत, अपरिक्षत, क्षतहीन, असंजातव्यथ, निर्व्रण.

Scatter, *v. t.* कॄ 6 P, वि-आ-अव-प्र-˚, प्रसृ c., विक्षिप् 6 P; (away) विश्लिष् c., निर्धू 5, 9 U, विभिद् c.; निरस्, 4 U, अपनुद् 6 P; वि-द्रु c. (army): *See* **Dispel, Disperse. -v.** *i.* विकृ pass., दिशि दिशि निर्गम् 1 P or प्र-या 2 P, बहुधा विक्षिप् pass. **-ed,** *a.* प्र-वि-आ-कीर्ण, विक्षिप्त, व्यस्त, प्रसृत, प्रसारित, विनिर्धूत, असंहत विश्लिष्ट, विभिन्न. **-ing,** *s.* विकिरणं, विक्षेपणं, &c.

Scavenge, *v. t.* सं-मृज् 2 P, 10. **-er,** *s.* संमार्जकः, खलपूः, बहुकरः, मल-अवस्कर-वाहः.

Scene, *s.* स्थलं, स्थानं, भूमि *f.*; 'the s. lie in Hastinapura' स्थलं हस्तिनापुरं. **2** अपटी; य(ज)वनिका, नेपथ्यं, रंगसज्जा. **3** प्रवेशः. **4** रंगः,-भूमिः,-शाला. **5** दृश्यं, दृग्गोचरं स्थानं, आलोकः, दृक्पातविषयः; oft. by स्थानं, आलोकः, or other words: 'this is indeed a lamentable s.' नन्वनुशयस्थानमेतत् (Mal. 8); रमणीयालोकं तत्स्थानं, &c.; अहो अधिकरणमंडपस्य परा श्रीः (Mr. 9) 'how splendid the s. of (presented by) the Court of Justice *See* **Present** also **-Scenery,** *s.* Ex. by भूमिः, स्थानं; *See* above. **2** गृहवृक्षादिरचना, कृत्रिमरचना.

Scent, *s.* गंधः, अधिवासः; 'sweet s.' आमोदः, परिमलः (arising from trituration), सौरभं; *See* **Fragrance;** 'diffusing s.' निर्हारी, समाकर्षी; 'having a sweet s.' सुगंधि, इष्टगंध, सुरभि, घ्राणतर्पण. **2** (Organ) घ्राणं, घ्राणेंद्रियं, घ्राणशक्ति *f.*, 'having a quick s.' तीक्ष्णघ्राण. **-v.** *t.* घ्रा 1 P, उप-आ-˚. **2** वास् 10, सुरभीकृ 8 U, धू c., धूप् 1 P, 10. **-ed,** *a.* सु-,वासित, सुरभि, सुगंधि, सुरभीकृत, सामोद, भावित, सगंध. **-less,** *a.* निर्गंध, गंधहीन.

Sceptic, *s.* संदेहभृत् *m.*, हैतुकः, अप्रत्ययिन् *m.*, अविश्वासी. **-al,** *a.* हैतुक, अप्रत्ययिन्, संशयात्मन्. **-ism,** *s.* संदेहः, हैतुकता, अविश्वासः.

Sceptre, *s.* दंडः, राजदंडः-वेत्रं-यष्टि *f.* **2** राजाधिकारः, प्रभुत्वं, आधिपत्यं; 'hold the s.' महीं शास् 2 P, *See* **Reign. -ed,** *a.* दंडधर, दंडभृत्; 's. king' अभिषिक्तो राजा.

Schedule, *s.* पत्रं, लेख्यं. **2** परिसंख्या, परिशिष्टं.

Scheme, *s.* उपायः, कल्पना, प्रयोगः, संकल्पः, प्रबंधः, प्र-,युक्ति *f.* **2** पद्धति *f.*, व्यवस्था; 'secret s.' गूढमंत्रणा, कपटप्रबंधः, कुटिलनयः. **-v.** (मनसा) परि-,क्लृप् c., उपायं चिंत् or युज् 10. **-ing,** *a.* कुटिलनयनिष्णात, युक्तिमत्, विदग्ध; अनुसंधायिन् (in a good sense).

Schism, *s.* भेदः, शाखा, धर्म-मत-भेदः. **-atic,** *a.* मतभेदमूलक.

Scholar, *s.* शिष्यः, छात्रः, अंतेवासिन् *m.*; *See* **Pupil;** 's. of a s.' प्रशिष्यः. **2** वृत्तिभुज् *m.*, वृत्तिभाक्. **3** पंडितः, कृतविद्यः, विद्वान्; *See* **Learned, Wise.-ly,** *a.* पंडितोचित, पांडित्ययोगिन्. **-ship,** *s.* पांडित्यं, वैदुष्यं, विद्या. **2** वृत्ति *f.*, वेतनं.

Scholiast, *s.* टीकाकारः, टीकाकृत् *m.*, वृत्तिभाष्य-कारः. **-Scholium,** *s.* टीका, भाष्यं, वृत्ति *f.*

School, *s.* विद्यालयः, विद्यागारं-गृहं-मंदिरं, पाठशाला, अध्ययनस्थानं. **2** शिष्य-छात्र-समूहः. **3** शाखा, संप्रदायः; 's. of philosophy' दर्शनं; 's. boy' बालशिष्यः, युवच्छात्रः; 's.-fellow' सहाध्यायिन् *m.*, सतीर्थः-र्थ्यः, एकगुरुः; 's.-man' तार्किकः, नैयायिकः; 's.-master' आचार्यः, गुरुः, उपदेशकः, उपाध्यायः, पाठशालाधिकृतः-अध्यक्षः. **-v.** *t.* शिक्ष् c., वि-नी 1 P, अधि-इ c. (अध्यापयति); *See* **Instruct. -ing,** *s.* शिक्षणं, अध्यापनं, उपदेशः. **3** गुरुदक्षिणा शिक्षामूल्यं.

Schooner, *s.* द्विकूपका नौः.

Sciatica, *s.* कटिशिरावेदना.

Science, *s.* वि-,ज्ञानं; *See* **Knowledge. 2** विद्या, शास्त्रं. **-Scientific,-al,** *a.* शास्त्रानुसारिन्, विज्ञान-शास्त्र in comp. **2** कृतविद्य, विद्वस्, आगमिन्, विज्ञानविद्.

Scimitar, *s.* खड्गः, असिः; निस्त्रिंशः, करवालः; *See* **Sword.**

Scintilla, *s.* अणुः,कणः, स्फुलिंगः. *v. t.* **-te,** स्फुलिंगान् मुच् 6 P or उत्क्षिप् 6 P; 'a blazing fire will s. in all directions' अग्नेर्ज्वलतः सर्वा दिशो विस्फुलिंगा विप्रतिष्ठेरन् (S. B. 109). **2** स्फुर् 6 P, भ्राज् 1 A, प्रकाश् 1 A; *See* **Shine. -tion,** *s.* स्फुरणं; अग्निकणः, स्फुलिंगनिर्गमः; 'in the state of s.' स्फुलिंगावस्थ *a.*

Sciolist, *s.* पल्लवग्राहिपंडितः, किंचिज्ज्ञः, (शास्त्र-) चुंबकः. **-Sciolism,** *s.* पल्लवग्राहित्वं, किंचिज्ज्ञता.

Scion, *s.* नवपल्लवः, किसलयः, अंकुरः, प्ररोहः. **2** वंश्यः, वंशजः; 'the s. of the family of some one' कस्यापि कुलांकुरः (S. 7.)

Scirrhus, *s.* मांसग्रंथिः.

Scissors, *s.* कर्तरी, खंडधारा, कर्तरिका, कृपाणी, छेदनी.

Scoff (at), *v.* अव-उप-हस् 1 P, अव-आ-अधि-क्षिप् 6 P, अव-ज्ञा 9 U, तिरस्कृ 8 U, धिक्कृ, अवमन् 4 A, परिहृ; *See* **Contemn, Mock.** **-ing,** *s.* अव-उप-हासः, अव-अधि-क्षेपः, अवज्ञा, अवमानः, धिक्कारः. **-ingly,** *adv.* सोपहासं, साक्षेपं.

Scold, *v. t.* निर्-,भर्त्स् 10 A, परुषं निंद् 1 P, आक्रुश् 1 P, आ-अधि-क्षिप् 6 P, गर्ह् 1, 10 A, अप-परि-भाष् 1 A, उपालभ् 1 A; *See* **Reproach.** **-s.** कर्कशा, दुर्मुखी, कैकेयी, वक्रशीला. **-er,** *s.* निंदकः, भर्त्सकः. **-ing,** *s.* भर्त्सनं-ना, निंदा, उपालंभः, आक्रोशः. परिभाषणं, &c.

Sconce, *s.* तुंडः. **2** आश्रयस्थानं, शाला, आश्रयः. **3** **Fort,** q. v. **4** दीपाधारः. **-v. t.** दंड् 10; *See* **Fine.**

Scoop, *s.* दर्वी, कंबि-वी *f.*; *See* **Ladle. 2** कोटरः-रं, पुटं. **3** खनित्रं. **-v. t.** दर्व्या अवपत् *c.* or अवतॄ *c.* **2** उत्खन् 1 P. खनित्रेण पुटीकृ 8 U.

Scope, *s.* आशयः, अभिप्रायः, हेतुः, अर्थः, तात्पर्यं, उद्देशः. **2** विषयः, प्रसरः. परिमाणं, पर्यंतः, अवधिः, सीमा; 'mind of limited s.' अल्पविषया मतिः (R. I. 2). **3** अवसरः, अवकाशः; लब्धावकाशा मे प्रार्थना (S. 1.) 'has found a s. (for itself)'.

Scorch, *v. t.* अभि-सं-तप् 1 P or *c.*, निर्-परि-दह् 1 P, प्लुष् 1 P, भ्रस्ज् 6 P, (in a pan); 's. ed with heat' आतपाक्रांत, 's. ed with the fire of missiles' अस्त्रपावकप्लुष्ट. **-ing,** *a.* दाहक, तापक, अत्युष्ण, अतितिग्म, उग्र, प्रखर, नैदाघ (घी *f.*).

Score, *s.* विंशति *f.* **2** अव-,च्छेदः, भंगः, दंतः. **3** रेखा, चिह्नं. **4** गणना, गणनापत्रं-लेखः. **5** विन्यासः (in music). **6** हेतुः, कारणं, निमित्तं; विषयः, अर्थः; 'on that s.' तस्मिन्विषये, तदर्थं; 'on the s. of friendship' सख्यहेतोः &c. **-v. t.** अवच्छिद् 7 P, दंतुरीकृ 8 U, भंगं कृ. **2** अंक् 10; रेखाभिः अंकू. **3** अभि-,लिख् 6 P, गण् 10; (ऋणं or देयं) गण् or पत्रे लिख् 6 P.

Scoria, *s.* *See* **Dross.**

Scorn, *v. t.* निर्-अव-धू 5, 9 U, तिरस्कृ 8 U, अवज्ञा 9 U, अवमन् 4 A, उपेक्ष् 1 A, परिहृ 1 P, न्यक्कृ, धिक्कृ, परुषं निंद् 1 P. **-s.** (अत्यंत) अवज्ञा, अवमानः, तिरस्कारः, धिक्कारः, परिभवः, उपेक्षा; *See* **Contemn Contempt.** **2** अवलेपः, दर्पः; *See* **Pride.** **-er,** *s.* अवमंतृ *m.*, तिरस्कर्ता, निंदकः. **-ful,** *a.* सावमान, सावज्ञ, तिरस्कारिन्, अवमानिन्, निंदात्मक; अवज्ञागर्भ; सावलेप, दृप्त. **-fully,** *adv.* सावज्ञं, सावमानं, सावलेपं.

Scorpio, *s.* वृश्चिकः.

Scorpion, *s.* वृश्चिकः, अ(आ)लिः, द्रु-(द्रो)णः; 'the sting of a s.' लूमं.

Scot, *s.* करः, देयभागः; 's.-free' अक्षत, अविकल, निर्व्रण.

Scotch, *v. t.* छेदैः अंक् 10, ईषत् छिद् 7 P. **2** अव-रुध् 7 U.

Scoundrel, *s.* खंडितवृत्तः, जाल्मः, दुरात्मन् *m.*, अधमः, नराधमः, निकृष्टः, खलः, दास्याः पुत्रः; (in voc.) कानेलीमातः; *See* **Rascal.**

Scour, *v. t.* सं-परि-मृज् 2 P or *c.*: निर्णिज् 3 U, घर्षणेन क्षुद् *c.*, निर्धुष् 1 P. **2** **Purge,** q. v. **-v. i.** (Off, along) द्रुतं-जवेन-शीघ्रं-अपक्रम् 1 U, 4 P or धाव् 1 P or पलाय् 1 A, द्रुतं तॄ 1 P or अतिक्रम्. **-er,** *s.* निर्णेजकः, वस्त्रधावकः. **-ing,** *s.* मार्जनं, निर्णेजनं.

Scourge, *s.* कशा-षा, प्रतिष्कशः-षः, प्रतोदः, ताडनरज्जु *f.*; (fig.) धूमकेतुः, उपप्लवः, उत्पातः, कृतांतः, कालः, पीडकः. **-v. t.** कशया हन् 2 P or तड् 10 or प्रह् 1 P; 'fit to be s. ed' कश्य. **2** अत्यंतं पीड् 10 or अर्द् 1 P or *c.*; उप-द्रु 1 A. **-ing,** *s.* कशाघातः, कशाताडनं-प्रहारः.

Scout, *s.* चारः, चरः, प्रणिधिः, अपसर्पः, गूढचरः; *See* **Spy.** **-v. i.** संचर् 1 P, गूढं-प्रच्छन्नं परचेष्टां निरूप् 10. **-v. t.** अव-उप-हस् 1 P, सहासं निरस् 4 U or निराकृ 8 U or प्रत्यादिश् 6 P.

Scowl, *s.* भ्रूभंगः, भ्रु(भ्रू)कुटि-टी *f.* **-v. i.** भ्रुकुटिं बंध् 9 P, कृ 8 U with (*s.*), भ्रुवौ संकुच् 1 P, भ्रूभंगेन दृश् 1 P; *See* **Frown.** **-ing,** *a.* सभ्रूभंग; 'with a s. look' सभ्रूभंगं, भ्रुवोर्भेदात्.

Scraggy, *a.* रूक्ष, कर्कश; *See* **Rough, Hard. 2** कृश, क्षाम, क्षीण; *See* **Lean.**

Scramble, *v. i.* हस्ताभ्यां धृत्वा-मंदंमंदं आरुह् 1 P. **2** संमर्दं-कलहं-कृ 8 U (with dat.); झटिति संग्रह् 9 P, ग्रहीतुं उद्यम् 1 A; 's. ed for water' जलाहरणार्थं परस्परं संमर्दमकुर्वन्. **-s., -ing,** *s.* मंदं मंदं आरोहणं. **2** सरभसग्रहणं, संमर्दः.

Scrap, *s.* खंडः, शकलः-लं, लवः, अंशः; 's. s of what is eaten' फेला, भुक्तसमुज्झितं; उच्छिष्टं, पिंडः; 's.-book' खंडाधारः, ग्रंथखंडाधारः.

Scrape, *s.* कृच्छ्रं, संकटं, आपद् *f.*, दुर्गं, कष्टं, दुःखं, दुर्गति *f.*, दुर्दशा; 'got into a s.'

कृच्छ्गत, आपद्गत, दुःस्थित. 2 घर्षणं. -v. i घृष् 1 P: लिख् 6 P, उत्-वि-°, तक्ष् 1, 5 P, त्वक्ष् 1 P, खुर् 6 P. 3 घर्षणेन प्रमृज् 2 P or निर्णिज् 3 U or अप-नी 1 P or क्षुभ् c.; (with feet) अपस्कृ 6 P. 4 (Together) (कष्टेन or महाप्रयत्नेन) समाहृ 1 P, संचि 5 U, संग्रह् 9 P, एकीकृ. -er, s. उल्लेखनी, निर्घर्षणी, निर्घर्षणकः. 2 काष्ठकुद्दालः. -ing, s. घर्षणं, उल्लेखनं, तक्षणं, क्षुरणं. 2 विदलं, तष्टं; अव(प)स्करः, अवकरः, मलं.

Scratch, v. t. वि-उत्-प्रोत्-लिख् 6 P, वि-अव-दॄ 9 P or c.; छिद् 7 P, निर्भिद् 7 P, खुर् 6 P: 's. with the nail' नखेन क्षण् 8 P or अंक् 10 or लिख्. 2 कंडूयति-ते (D.): नखैः घृष् 1 P. 3 (As birds) विष्कृ 6 P, अपस्कृ. 4 ईषत् क्षण् or उल्लिख्. 5 *Scrawl*, q. v. 6 (Out,) प्रमृज् 2 P, विलुप् 6 P or c., निर्घृष्, उच्छिद् 7 P, विनश् c.: *See* **Erase.** -s. (त्वचः) उल्लेखनं, दारणं, छेदः, भेदः; क्षतं, घर्षणं; व्रणः; 's. with the nail' नखक्षतं, नखांकः-व्रणः-पदं. 2 ईषत्क्षतं, त्वग्व्रणः; 'hard s.' ओरफः. -er, s. उल्लेखकः, विदारकः, कंडूयनकः; विष्किरः. -ing, s. उल्लेखनं, विदारणं, छेदः, &c.; कंडूयनं, कंडूया, कंडूति *f.*

Scrawl, v. t. अस्पष्ट-स्थूलं-लिख् 6 P, स्थूलाक्षरैः-अतिक्षिप्रं-लिख्. -s., -ing, s. अस्पष्ट-स्थूल-लेखः.

Scrawny, *See* **Lean.**

Scream, v. i. आ-उत्-वि-क्रुश् 1 P, उच्चैः नद् 1 P or वि-,रु 2 P, वाश् 4 A (of birds): रवं मुच् 6 P, उच्चैः आक्रंद् 1 P, चीत्कारशब्दं कृ 8 U. 's. with pain' आर्तवत् रु, आर्तनादं मुच्. -s, -ing, s. आक्रंदनं, उत्क्रोशः, चीत्कारः, उच्चनादः-रवः, कोलाहलः, विक्रुष्टं; 's. of pain' आर्तरवः-नादः.

Screech, *See Scream*; 's.-owl' नक्तचारी उलूकः, कालपेचकः.

Screen, s. आवरणं, व्यवधा-धानं, तिरस्करिणी, ज(य)वनिका; अंतर्धा-धानं, प्रतिसीरा. -v. t. प्र-,छद् 10, निगुह् 1 U, गुप् 1 P, (crime &c.); नि-आ-सं-वृ 5 U or c., व्यव-धा 3 U, पिधा, अंतर्धा. 2 रक्ष् 1 P: आश्रयं दा 3 U, आश्रयदानेन प्रच्छद्, &c.

Screw, s. कर्षणी, व्यावर्तनकीलः. 2 कृपणः, बद्धमुष्टिः. -v. t. कर्षण्या-कीलकेन-बंध् 9 P. 2 व्या-परि-वृत् c. 3 (Out) निष्पीड् 10, निर्ह् 1 P, निष्कृष् 1 P, निर्दुह् 2 U. 4 पीड्, अर्द् 1 P or c., बाध् 1 A, उपद्रु 1 A

Scribble, *See* **Scrawl.**

Scribe, s. लेखकः, लिपिकारः, अक्षरचणः, कायस्थः.

Scrip, s. पुटः, पुटी, क्षुद्रकोषः. 2 लेखः, पत्रं, लेख्यं.

Scripture, s. वेदः, श्रुति *f.*, आम्नायः, निगमः. 2 शास्त्रं; 'religious s.' धर्मशास्त्रं; 'authority of the s.s' शास्त्रप्रमाणं. -al, a. शास्त्रसिद्ध-उक्त, श्रुतिविहित, शास्त्र in comp.; 's. prohibition' शास्त्रप्रतिषेधः.

Scrivener, s. कुसीदः; *See* **Usurer.** 2 लेखकः, लिपिकारः, लेखकवृत्तिः.

Scrofula, s. गंड-कंठ-माला. -**Scrofulous,** a. गंडमालिन्.

Scroll, s. पट्टः, लेख्यं, दीर्घपत्रं-पट्टः.

Scrotum, s. मुष्कः, अंडः, फलं, कोशः-षः, अंड-मुष्क-फल-कोशः-षः, वृषणः.

Scrub, v. t. अत्यंतं मृज् 2 P or c. or प्रक्षल् 10 or निर्णिज् 3 U or घृष् 1 P. -s. व्रातीनः, अधम-नीच-जघन्य-वृत्तिः. -**Scrubby,** a. तुच्छ, निकृष्ट, हीन; *See* **Mean.**

Scruple, s. संदेहः, आ-,शंका, संशयः, विकल्पः. -v. i. विकॢप् 1 A or c., संदिह् 2 U, शंक् 1 A, वि-आ-परि-°; ex. by 'Doubt', q. v. -**Scrupulous,** a. सरल, ऋजु. 2 सूक्ष्म, निपुण, अतिसूक्ष्म, अतिसूक्ष्मदृष्टि. 3 साशंक, शंकाशील, आ-,शंकित.

Scrutiny, s. निपुणपरीक्षणं, सूक्ष्मनिरूपणं-परीक्षा-दर्शनं, अनुसंधानं, निरूपणं. -eer, s. सूक्ष्मनिरूपकः. -ize, v. t. सूक्ष्मं-निपुणं-दृश् 1 P or परीक्ष् 1 A or निरूप् 10, निपुणं अनुसं-धा 3 U or अनुयुज् 7 A or अन्विष् 4 P. -izer, s. सूक्ष्मनिरूपकः, निपुणपरीक्षकः, सूक्ष्मदर्शिन् *m.*

Scud, v. i. अतिवेगेन-सहसा-गम् 1 P or चल् 1 P.

Scuffle, s. तुमुलं, नियुद्धं, कलहः, बाहूबाहवियुद्धं, द्वंद्वं, -v. i. बाहूबाहवि युध् 4 A.

Sculk, v. i. निभृते-गूढस्थाने-वृत् 1 A or स्था 1 P, गुप् pass: 's. off' व्यपसृप् 1 P, पलाय् 1 A, अपक्रम् 1 U, 4 P. -er, s. गुप्तवर्तिन् *m.*

Scull, s. कपालः-लं, शिरोस्थि *n.*, करोटि-टी *f.*, कर्परः. 2 क्षुद्रक्षेपणि *f.*: 's.-cap' शिरस्कं, मस्तकावरणं.

Scullery, s. पात्रक्षालनकुटी.

Scullion, s. पात्रक्षालकः-मार्जकः.

Sculptor, s. त्वष्टृ *m.*, तक्षकः, तष्टृ *m.*, तक्षन् *m.* -**Sculpture,** v. t. तक्ष् 1, 5 P, त्वक्ष् 1 P, उल्लिख् 6 P, प्रतिमां कृ 8 U or निर्मा 3 A. -s. तक्षणं, त्वक्षणं, प्रतिमा-मूर्ति-करणं. 2 प्रतिमा, मूर्ति *f.*

Scum, s. मंडः-डं, फेनः-नः; 's. of boiled rice' निस्रावः, आचामः; *See* under **Rice.** 2 मलं, उच्छिष्टं, अवस्करः, अवकरः, कल्कं, असारद्रव्यं, किट्टं; (fig.) मलं; मलं पृथिव्या बाह्लीकं (Mah. VIII 45. 23) 'are the s. of the (whole) world.'

Scurf, s. शुष्कचर्मन् *n.*, किलासं, सिध्मं *See* **Itch.** (dry).

Scurrile, Scurrilous, *a.* परुष, तीक्ष्ण; दुर्वक्त,अश्लील,अदक्षिण, दुर्वाच्य.2 कटुभाषिन्, दुर्मुख, मुखर, वाग्दुष्ट. *Scurrility, s.* पारुष्यं, मौखर्यं, दुरुक्तं, &c.

Scurvy, *s.* शीतादः, लवणरक्तं. *-a.* कुत्सित, गर्ह्य, तुच्छ, नीच; *See* **Mean.**

Scutcheon, *s.* कुलीनचिह्नपत्रं, कौलीनकोषः. [1 A.

Scuttle, *s.* करंडः, मंजूषा. **2** छिद्रं. *-v. i.* त्वर्

Scythe, *s.* लवित्रं, दात्रं, खड्गिकं, शस्यकर्तरिका.

Sea, *s.* सागरः, समुद्रः, उदधिः, अर्णवः, जलधिः, वारिधिः, अंपांपतिः; *See* **Ocean;** 'a rough s.' क्षुब्धार्णवः; 's. of worldly existence' भवसागरः, संसारार्णवः; 's. of troubles' क्लेशसागरः, दुःखार्णवः, &c.; 'go to s.' नाविकः-सांयात्रिकः-भू 1 P, नाविकवृत्तिं सेव् 1 A; 'beyond the s. s' द्वीपांतरं-रे; 's.-beat' तरंगाहत; 's.-faring' समुद्रग-यायिन्, सांयात्रिक; 's.- fight' नौयुद्धं; 's.- girt' *See* **Girt;** 's.-green' श्यामहरित, सागरवर्ण; 's.-gull' करेटुः; 's.-man' नाविकः, समुद्रगः, पोतवाहः;'s.-port' पोताश्रयस्थानं, पोतशरणं, नौकाश्रयः; 's.-shore' समुद्रतटं-तीरं, वेला, रोधस् *n.*; 's.-sick' समुद्रच्छर्दिरुग्णत; 's.-side' समुद्रवेला &c.

Seal, *s.* मुद्रा, (fig. also): 'opening the s. of sleep' क्षिपन्निद्रामुद्रां (Mal. 2); 'open it, preserving the s. and show me' मुद्रां परिपालयन् उद्घाट्य दर्शय (Mu. 5); 's. of the lips' ओष्ठमुद्रा. **2** मकरः, नक्रः *-v. t.* मुद्रयति (D.). **2** निर्णी 1 P, स्थिरीकृ 8 U, दृढीकृ, दृढयति (D.); 'the defeat in that battle s. ed his fate' पराजयेन तेन तस्य भाविगतिः एकांततः निर्णीता. **2** मुद्रया अंक् 10 or चिह्नयति (D.). **3** (मुद्रया) पि-धा 3 U, बंध् 9 P; मुखं बध्नाति 's. s the lips'. *-ed, a.* मुद्रित, कृतमुद्र, मुद्रांकित, मुद्राबद्ध; 's. ing wax' ला(रा)क्षा; *See* **Lac.**

Seam, *s.* संधिः; सीवनं; 's. of planks' काष्ठसंधिः. **2** शुष्कव्रणः. *-y, a.* संधियुक्त; 'turn the s. side within' सव्रीडान् प्रच्छादय-निगूह. **-Seamstress,** *s.* सूचिका, सूचिकर्मोपजीविनी.

Sear, *v. t.* निर्दह् 1 P, प्लुष् 1 P; दहनेन दृढीकृ or शुष्कीकृ 8 U. *-a.* संशुष्क, विशीर्ण, म्लान.

Search, *v.* (For) अन्विष् 4 P, निरूप् 10, अनुसंधा 3 U, मृग् 10 A, मार्ग् 1 P, 10, विचि 5 U, निर्-अव-ईक्ष् 1 A; (fig.) निपुणं परीक्ष् or निरूप्; s. into' निरूप्, परीक्ष्; 's. out' अन्विष्य &c. उपलभ् 1 A or प्राप् 5 P. *-ing, s.* अन्वेषणं-णा, मार्गणं, निरूपणं, अनुसंधानं, निरीक्षणं, अन्वीक्षणं; विचयः, जिज्ञासा. *-er, s.* अन्वेषकः, अन्वेष्टृ *m.*, निरूपकः, निरीक्षकः; 's. of the human heart' पुरुषांतरवित्. *-ing, a.* निपुण, सूक्ष्म, अवहित; 'casting at me a s. look' सुनिपुणं मां विलोक्य.

Season, *s.* ऋतुः, कालः, समयः; (in general) कालः, वेला, समयः, अवसरः, अवकाशः, प्रस्तावः; 'auspicious s.' लग्नं, मुहूर्तः, शुभवेला,-लग्नं; 'in due s.' काले; 'pertaining to the s.' आर्तव (वी *f.*) ; 'out of s.' अकाले, अनवकाशे; 'in s. and out of s.' कालेऽकाले वा, औचित्यानौचित्यमविचार्य; 'wrong s.' अकालः, अनवकाशः. *-v. t.* अधि-,वास् 10, उपस्कृ 8 U or रस्रा-दूकृ. **2** पच् 1 P, परिपाकं उ त्पद् c., पक्वीकृ; *See* **Mature. 3** (Accustom) ex. by परिचय, सहिष्णु, &c.; 's. ed to heat' रविकिरणसहिष्णु (S. 2); 's. s the body to exertions' श्रमजयात् तनुं प्रगुणां करोति (R. ix. 49); 's. ed to exertions' जितश्रम, श्रमसहिष्णु. **-able,** *a.* समयोचित, कालानुरूप, प्रस्तावसदृश (शी *f.*), प्राप्तकाल, कालोचित, and sim. comp. **2** कालकृत, काल in. comp.;'s. efforts' कालकृतोद्योगाः. **3** आर्तव (वी *f.*), कालोद्भव, ऋतुज, ऋतव्य. **-ableness,** *s.* कालौचित्यं, प्रस्तावसादृश्यं, &c. **-ably,** *adv.* यथाकालं-समयं-अवसरं, काले, समये, प्रस्तावसदृशं, प्राप्तकालं, कालानुरूपं. *-ing, s.* उपस्करः, व्यंजनं.

Seat, *s.* आसनं, पीठः-ठं; 'take a s. here' अत्र आसनपरिग्रहं करोतु भवान्; पर्यंकः (s. on a sofa), विष्टरः (cane-s.); आस्तरणं; 'raised s.' वितर्दि-र्दी *f.*, वेदिका. **2** स्थानं, आयतनं, आस्पदं, धामन् *n.*, अधिष्ठानं, निकेतनं, नि-आ-लयः, आगारं, पदं, आशयः; 'capital s.' राजधानी-नगरं; 's. of justice' न्यायासनं, धर्मासनं, व्यवहारासनं; 's. of blood' रक्ताशयः; क्रोधस्थानं; निवासार्, &c. *-v. t.* (Oneself) आसने उपविश् 6 P, निषद् 1 P, आसनपरिग्रहं कृ 8 U; (another) (आसने) उपविश् c., आसनं ग्रह् c., अध्यास् c., अधि-ष्ठा c., (-ष्ठापयति). **2** प्रति-ष्ठा c., अधिकृ, अधि-आ-रुह् c., निविश् c.; 'he was s. ed on throne' राजपदमधिरोपितः, सिंहासने प्रतिष्ठापितः. *-ed, a.* आसीन, उपविष्ट, निषण्ण, अध्यासीन; आसनस्थ, आसनस्थित-उपविष्ट-आरूढ-गत-आश्रित, पीठस्थ; 's. at ease' सुखासीन, सुखोपविष्ट; 'be s.' गृह्यतां आसनं, क्रियतामासनपरिग्रहः. **2** प्रतिष्ठित, निविष्ट, स्थित, गत-स्थ- निष्ठ in comp.;'s.in

the heart ' हृदयनिष्ठ, हृत्स्थ ; कंठगत अस्थिनिष्ठ, &c.

Secede, *v. i.* अपसृ 1 P, अपगम् 1 P, अप-या-इ 2 P, अपक्रम् 1 U, 4 P: व्यपसृ &c.; (to) आश्रि 1 U, अव-आ-लंब् 1 A: (from) (धर्म &c.) त्यज् 1 P, उत्सृज् 6 P; मतांतरं ग्रह् 9 U or आश्रि &c. **-er,** *s.* भिन्नमताश्रितः; मतांतरग्राहिन् *m.* **-Secession,** *s.* अपसरणं, अपगमःमनं, अपक्रमःमणं, &c. 2 मतांतरस्वीकारः-ग्रहणं, स्वधर्मत्यागः.

Seclude, *v. t.* नि-अव-रुध् 7 U, गुप् 1 P. 2 विविक्ते वस् c., पृथक् कृ 8 U; वि-विच् 3, 7 U or c. 3 (Oneself) विविक्तं आश्रि 1 U or सेव् 1 A, विविक्ते-एकांते-वस् 1 P, जनसंसर्गं त्यज् 1 P or परिहृ 1 P or वृज् 10. **-ed,** *a.* विविक्त, निर्जन, विजन, निभृत; *See* **Lonely.** 2 (Of persons) त्यक्त-मुक्तसंग, विविक्तसेविन्-वासिन्-वृत्ति. **-Seclusion,** *s.* रहस् *n.*, विविक्तता, एकांतता, विविक्तदशा- स्थिति *f.* रहःस्थानं, विविक्तं, एकांतवासः.

Second, *a.* द्वितीय; 's. to none', 'without a s.' अद्वितीय, अनुत्तर, अत्युत्तम; 's. in rank' द्वितीयपदभाक्. 2 **Secondary,** q. v.: 's.-hand' भुक्तपूर्व, अन्यभुक्त-व्यवहारित, अन्योपयुक्त; अन्यकल्पित, अन्यसृष्ट; 's.-hand information' अन्यस्मादधिगता वार्ता; 's.-hand witness' श्रुतसाक्षिन् *m.*'s.-rate' मध्यम, सामान्य; 's.-sight दिव्यचक्षुस् *n.* दृष्टि *f.* **-s.** विपलं; विकला; क्षणः निमि(मे)षः. 2 सहायः, सहकारिन् *m.*, उपकारी. **-v.** *t.* अनुमुद् 1 A, अनुग्रह् 9 P, उपकृ 8 U, अभिनंद् 1 P. **-er,** *s.* अनुमोदिन् *m.*, समर्थयितृ *m.*, पक्षोद्ग्राही. **-ly,** *adv.* द्वितीयतः, द्वितीयस्थाने. **-Secondary,** *a.* अप्रधान, गौण (णी *f.*), असुख्य, अनुषंगिन्, उपसर्जन, उपसृष्ट, अप्रथम; oft. by उप pr.; 'a s. planet' उपग्रहः; 'a s. rank' अप्राधान्यं. 2 मध्यम, सामान्य, सामान्यगुणक. **-ly,** *adv.* अप्राधान्येन, गौणतः, अप्रधानतः, अनुषंगतः.

Secret, *a.* नि-,गूढ, गुप्त, प्र-,छन्न, निभृत, संवृत, अव्यक्त, अप्रकाश, अविदित; 's. door' प्रच्छन्नं, अंतर्द्वारं. 2 गुह्य, गोप्य, रहस्य, संवरणीय. 3 गुह्याभेदिन्, रहस्याभेदिन्. 4 गहन, गूढ, अव्यक्त, गूढार्थ, गहनार्थ. 5 रहस् in comp., विविक्त, निर्जन, निभृत; 'keep s.' गुह् 1 U, छद् 10; *See* **Conceal.** **-s.** रहस्यं; गुह्यं, गोप्यं, मर्मन् *n.*, 'have you kept the s. entrusted to you' रक्षितं भवता रहस्यनिक्षेपः (V. 2): 'the s. of one's power' शक्तेःरहस्यं; 'the s. of good men (of their conduct)' साधूनां रहस्यं (U. 2); 'in s.' रहसि, रहः, मिथः; 's. counsel' मंत्रः, गूढमंत्रः; 'knowing s. s' रहस्यज्ञ, अंतर्वेदिन्, मर्मविद्; 'the matter is no longer a s.' बहुलीभूतः-प्रकाशतां गतः-सोऽर्थः; 'diving into the s. s of others' परमर्मभेदिन्, मर्मान्वेषिन्, पररहस्यविद्. **-ly,** *adv.* प्र-,छन्नं, गूढं, निभृतं, गुप्तं, अव्यक्तं, उपांशु, गूढ-गुप्त in comp.; 'walking s.' गूढाचार, गुप्तसंचारिन्. **-ness,-Secrecy,** *s.* गुप्तता, गूढता, प्रच्छन्नता, गुप्ति *f.*, गुप्त-निभृत-भावः. 2 संवृत्ति *f.*, गुप्तिः, गुह्य-रहस्य-रक्षणं, गोपनं, रहस्याभेदः-पालनं, मौनं, अप्रकाशनं. 3 विविक्तताः रहः, रहोवासः, विविक्तवासः-भावः.

Secretary, *s.* कार्याधिकृतः, सचिवः.

Secrete, *v. t.* स्रु c., प्र-निः-परि°-, निर्गम् c., निःसृ c., उद्गम् 1 P, उद्-गॄ 6 P, उत्सृज् 6 P; (bile &c.) उत्-,रिच् 7 P or c.; उत्पद् c., जन् c ; 'the mouth frequently s. s saliva' मुहुर्वक्त्रं लालायते, लालां स्रावयति. 2 गुप् 1 P, गुह् 1 U, संवृ 5 U, अप-नि-ह्नु 2 A: *See* **Conceal.** **-ion,** *s.* स्रावः-वणं, उद्गमनं, उत्सर्गः, उत्पादनं. 2 मलं; 's. of the throat' कफः, श्लेष्मन् *m.*'s. of the bowels' पुरीषं, विष्ठा; *See* **Dung.**

Sect, *s.* शाखा, पथिन् *m.*, मार्गः, पक्षः, मतं, संप्रदायः, गणः. **-ary,-arian,** *a.* शाखागत, सांप्रदायिक (की *f.*); स्वपक्षानुसारिन्, शाखावलंबिन्, शाखाश्रित.

Section, *s.* वि-,भागः, छेदः, परिच्छेदः; खंडः-डं, पर्वन् *n.*, प्रकरणं, उल्लासः, उच्छ्वासः, स्कंधः, कांडः-डं, पादः (of different compositions). 'sub-s.' अधिकरणं.

Sector, *s.* वृत्तखंडं.

Secular, लौकिक-ऐहलौकिक-सांसारिक-ऐहिक-प्रापंचिक-व्यावहारिक-(की *f.*). **-ity, -ness,** *s.* ऐहिकत्वं; संसारासक्ति *f.*, प्रपंचानुरागः.

Secure, *a.* सुरक्षित, अकुतोभय, अभय, निर्भय, गतभय, अनाहय, निराबाध, निर्विघ्न; (of persons) निःशंक, अशंक, निश्चिंत, निरातंक, निरपेक्ष, स्वस्थ. **-v. t.** रक्ष् 1 P, भयं निवृ c., or निवृत् c. or निरस् 4 P, निर्भयीकृ 8 U; ex. by (*a.*) with कृ. 2 स्थिरीकृ, दृढीकृ, निर्णी 1 P. 3 दृढं बंध् 9 P; 's. ed with a bolt' अर्गलाबद्धं (द्वारं). 4 आक्रम् 1 U, 4 P, ग्रह् 9 U. **-ity,** *s.* रक्षाक्षणं, गुप्ति *f.*, स्थैर्यं, परि-,त्राणं, गोपनं, क्षेमःमं, निर्भयत्वं, अहार्यता, शंकाभावः, अभयं. 2 अभयवाच् *f.*, अभयदानं-दक्षिणा. 3 रक्षकः, शरणं, आश्रयः. 4 प्रतिभूः, बंधकः, लग्नकः (persons); प्रातिभाव्यं, आधिः, न्यासः, निक्षेपः; *See* **Pledge.** **-ly,** *adv.* निःशंकं, निर्भयं, क्षेमेण, निराबाधं.

Sedan, *s.* शिबिका.

Sedate, *a.* धीर, शांत, स्तिमित, गंभीर, निरुद्वेग, अनाकुल, अक्षुब्ध, अचंचल. **-ly,** *adv.*

धीरवत्, शांतं, अनाकुलं, निरुद्वेगं. -ness, s. धीरता, शांतता, गांभीर्यं, अनुद्वेगः, अक्षोभः, स्थैर्यं, गौरववृत्ति f. -Sedative, a. शांतिकर (री f.), शीतल, शांतिद, शमक. -s. लंघनं, अप-,कर्षणं.

Sedentary, a. निरुद्योग, अचपल, अव्यवसायिन्, अनुद्योगशील, अव्यायामिन्, चलनगति-हीन.

Sedge, s. तृणं.

Sediment, s. मलं, खलं, कल्कं, किट्टं, उच्छिष्टं, शेषः-षं.

Sedition, s. राजद्रोहः, प्रजाप्रकोपः संक्षोभः, प्रकृतिक्षोभः, भेदः, कलहः, 'fomenting s.' उपजापः, भेदजननं. -Seditious, a. राजद्रोहिन्; (causing s.) प्रजासंक्षोभजनन (नी f.), प्रजा-प्रकृति-क्षोभकर (री f.), भेदकर, उपजापक. -ly, adv. राजद्रोहपूर्वं, सोपजापं.

Seduce, v. t. दुष् c. (दूषयति), वि-,मुह् c., विलोभ्य अपहृ 1 P. सत्पथात् प्रभ्रंश् c. or च्यु c.; प्र-वि-लुभ् c., आ-वि-कृष् 1 P. आक्षिप् 6 P; (a. woman) दुष् c., सतीत्वात् भ्रंश् c.,चारित्र्यं नश् c.; पापमार्गे प्रवृत् c.; अभिगम् 1 P. -er, s. दूषकः, प्रलोभयितृ m., प्र-वि-लोभकः, आकर्षकः, वि-मोहकः. -Seduction, s. प्र-वि-लोभनं, आकर्षणोद्यः,विमोहनं,आकर्षणं. 2प्रतारणं-णा, वंचनं-ना, विप्रलम्भः. 3 दूषणं, शीलपातनं, सतीत्वनाशः,चारित्र्यभ्रंशः, संग्रहणं. -Seductive, a. प्र-वि-लोभक, आकर्षक, वि-,मोहिन्.

Sedulous, a. उद्यमिन्, उद्योगासक्त, उद्यमतत्पर, कार्यव्यापृत, अभिनिविष्ट. -ly, adv. आसक्तिपूर्वं, साभिनिवेशं, सोद्यमं. -ness, s. कार्यासक्ति f., उद्योगशीलता, उद्यमपरता; See Industry-ous, &c.

See, s. धर्माध्यक्षाधिकारः. -v. t. दृश् 1 P, ईक्ष् 1 A, वि-सं-अव-प्र-निर्-;° लक्ष् 10, अव-,वे-आ-लोक् 1 A, 10, निरूप् 10, निर्वर्ण् 10 (carefully), आलोच् 10; 's. with one's own eyes' प्रत्यक्षीकृ 8 U, (कदाचिदस्याः प्रत्यक्षीकृता विक्रिया S. 7). 2 ज्ञा 9 U, बुध् 1 P,अवगम् 1 P,अव-इ 2 P, उपलभ् 1 A. 3 Beware, q. v.; 's. ing that' यतः, यस्मात्, यत्. -er, s. द्रष्टृ m., दर्शिन् m., 2 सिद्धः, भविष्यद्वादिन् m. -Sight, s. दर्शनं, विलोकनं, वीक्षणं, आलोकः &c. 2 (View) दृष्टिपथः-विषयः-गोचरः. 3(Eye) दृष्टि f., दृश् f., चक्षुस् n., नेत्रं, नयनं, दृक्शक्ति f. 4 आलोकः, कौतुकं, चमत्कारः; 'being within s.' दृश्य, दृग्गोचर, दृष्टिविषय; 'out of one's s.' परोक्षं-क्षे, अगोचरं-रेण; 'gone out of s.' अंतरित, अंतर्हित, तिरोहित; 'in s. of' समक्षं, प्रत्यक्षं, साक्षात्, with gen. or in comp.; 'at the very first s.' प्रथमदर्शनादेव, आमथदर्शनात्; 'charming the s.' दृष्टिमोहःबंधः. -ly, a. सुदृश्य, प्रेक्षणीय, ललित; See Pleasant.

Seed, s. बीजं, in all senses; 'growing from s.' बीजप्ररोह-रुह, बीज्य. 2 मूलं, आदिः, प्रभवः, उद्भवः; See Origin. 3 प्रजा, अपत्यं, वंशः, संतानः, संतति f. 4 शुक्रं, रेतस् n.; See Semen; 's.-corn' बीजधान्यं; 's.-time' बीज-वाप-कालः; 's.-vessel' बीजकोशः-शुक्ति f. -v. t. बीजं आरुह् c., बीजयति (D.). -v. i. बीजं प्रदा 3 U or उत्पद् c. -less, a.निर्बीज. -ling, s. बीजप्ररोहः, बीजांकुरः. -y, a. बीजिन्, बीजपूर्ण, बहुबीज. -Seedsman, s. बीजिन् m. 2 बीजविक्रयिन् m.

Seek, v. अन्विष् 4 P, मृग् 10 A, निरूप् 10, विचि 5 U; See Search. 2 कम् 1 A, आ-अभि-कांक्ष् 1 P, इष् 6 P; प्रार्थ् 10 A, अभ्यर्थ्, याच् 1 A: 's ing to get heaven' स्वर्गकामः. 3 प्र-,यत् 1 A, घट् 1 A, चेष्ट् 1 A, उत्-,जृंभ् 1 A; See Attempt. -er, s. अन्वेष्टृ m., निरूपकः, प्रार्थकः. -ing, s. अन्वेषणं. मार्गणं, निरूपणं.

Seem, v. i. भा 2 P, आ-प्रति-,° दृश-लक्ष्-pass., आभास् 1 A; See Appear; 'it s. s to me' मन्ये, शंके, इति मे मतिः. -ing, a. बाह्य, बहिः in comp., कृतक, कृत्रिम. -s. आभासः, बाह्यरूपं, आकारः. -ingly, adv. बहिः, बाह्यतः, आभासेन; 's. true' सत्याभास, सत्यसंकाश. -ly, a. विनीत, युक्त, उचित, संगत, उपपन्न; See Proper.

See-Saw, s. उत्तानतं, निम्नोन्नतं

Seethe. v. t. क्वथ् 1 P, पच् 1 P. -v. i. पच् pass. -r, s. स्थाली, उखा, पिठरः, ऋजीषं.

Segment, s. खंडः-डं, वि-,च्छेदः; (of a circle) वृत्तखंडं.

Segregate, v. t. वियुज् 7 A, 10, विश्लिष् c. -v. i. विश्लिष् 4 P, विभिद् pass; See Separate. -ion, s. वियोगः, विश्लेषः-

Seismal, Seismic, a. भूकंपसंबंधिन्.

Seize, v. t. सं-ग्रह् 9 P, धृ 1 P, 10, परामृश् 6 P, कल् 10 (कलयति); ग्रस् 1 A; 's. ing by the hair' केशेषु-केशैः-गृहीत्वा. 2 अप-,हृ 1 P, बलेन ग्रह् or धृ. 3 आपत् 1 P, अभिद्रु 1 P; See Attack. 4 आक्रम् 1 U, 4 P, अभिभू 1 P, उपसृज् 6 P, ग्रस्, उपहन् 2 P, आविश् 6 P; 's. ed with deep sleep' गाढनिद्राक्रांत; 's. ing an opportunity' गृहीतावसर, प्राप्तकाल, प्राप्तावसर, अवसरं प्राप्य-गृहीत्वा. -er, s. ग्रहीतृ m., हारिन्-ग्राहिन् in comp. -ure, s. ग्रहणं, धारणं, हरणं, सं-,ग्राहः, ग्रहः, ग्रसनं, आकलनं. 2 आक्रमः, आवेशः, अभिभवः, ग्रासः.

Seldom, *adv.* क्वचित्, कदाचित्, विरलं, दूर pr; 's. to be found' दुर्लभं.

Select, *v. t.* वृ 5 U or 10 (वरयति), वृं 9 U, उद्-धृ 1 P, उद्-ग्रह् 9 P, विशिष् 7 P or c. 2 संग्रह्, समुद्धृ, संकल् 10 (कलयति) **-a.** विशिष्ट, उत्तम, उत्कृष्ट; *See* **Choice. -ed,** *a.* वृत, वृत्त, व्यावृत्त, उद्धृत **-ion,** *s.* वरणं, उद्धरणं, वरः, वृत्ति *f.* 2 संग्रहः, सारः; 's. of poetical pieces' काव्यसंग्रहः.

Selenite, *s.* चंद्रकांतः.

Self, *a.* आत्मन्, स्व in comp., स्वीय, निज; *See* **Own;** 's.-interest' आत्महितं; 's.-destroyer' आत्मघातकः; (with pronoun) स्वयं, स्वतः. **-s.** आत्मन् (sing. and *m.*); देवी प्रातप्रसवमात्मानं गंगादेव्यां विमुंचति (U 7). In comp. ex. by आत्म, स्व, or स्वयं, स्वतः; 's.-accomplished' आत्मोपार्जित, स्वतः अर्जित; 's.-command' आत्मसंयमः, दमः, इंद्रियजयः; 's.-conceit अहंकारः ममत्वं, स्वाभिमानः; s.-denying' आत्मसंयमिन्, 's.-evident' स्वतःसिद्ध, स्वयंप्रकाश, प्रत्यक्ष; 's.-existent' स्वयंभू आत्मभू; 's.-interested' स्वार्थपर, स्वार्थबुद्धि; 's.-love' ममता, अहंमानः, स्वानुरागः; 's.-possessed' अव्यग्र, स्थिरात्मन्, स्वस्थचित्त, धृतिमत्; 's.-possession' धृति *f.*, स्वास्थ्यं, आत्म-स्व-निष्ठा; *See* **Presence,** (of mind); 's.-sufficient' स्वाभिमानिन्; 's.-will' स्वेच्छा, स्वैरिता, स्वाच्छंद्यं; 's.-willed' स्वैर, स्वैरिन्, स्वच्छंद, काम-स्वेच्छा-चारिन्, कामवृत्ति, स्वैरगति. **-ish,** *a.* स्वार्थपर-निष्ठ-परायण; उदरंभरि, स्वार्थदृष्टि-बुद्धि, स्वहितपर-निष्ठ, स्वहितैषिन्, स्वलाभनिष्ठ-तत्पर, &c. **-ishly,** *adv.* स्वार्थदृष्ट्या, आत्महितबुद्ध्या, स्वलाभेच्छया. **-ishness,** *s.* स्वार्थ-स्वलाभ-स्वहितपरता-निष्ठा-बुद्धि *f.*-दृष्टि *f.*, स्वलाभेच्छा, ममता.

Sell, *v. t.* वि-क्री 9 A (rarely P also). **-v. i.** मूल्येन विक्री pass.; 'this picture will s. for a large price' महता मूल्येनेदमालेख्यं विक्रेष्यते. **-er,** *s.* विक्रेतृ *m.*, विक्रयिन् *m.*, विक्रयिकः, पणायिता. **-ing, -Sale,** *s.* विक्रयः; पणनं; 'exposed for s.' क्रय्य, क्रयार्थं प्रसारित; 'an article for s.' पण्यं, पण्यद्रव्यं; 'underhand s.' अवक्रयः. **-Saleable,** *a.* विक्रेय

Selvage, *s.* *See* **Border.**

Semblance, *s.* आभासः, आभा, औपम्यं, सादृश्यं; आकारः, रूपं; 'it has a s. of truth' सत्यमिवावभासते, सत्यसंकाशं; 'to wear the s. of displeasure (anger)' कृतककोपं दर्शयितुं

Semen, *s.* शुक्रं, रेतस् *n.*, बीजं, वीर्यं, तेजस् *n.*, इंद्रियं. **-Seminal,** *a.* (*s.*) in comp.; 's. discharge' रेतःस्रावः-क्षरणं, निषेकः.

Semi, *a.* अर्ध or सामि in comp.; 's.-circle, वृत्तार्धं, अर्धवर्तुलं; 's.-form' अर्धाकृति &c. &c.

Seminary, *s.* बीजारोपणस्थलं. 2 शिक्षणालयः, विद्यामंदिरं.

Semi-vowel, *s.* अंतस्थः.

Sempiternal, *a.* See **Eternal.**

Sempstress, *s.* सूचिका.

Senate, *s.* वृद्ध-शिष्ट-सभा; मंत्रि-सचिव-सभा. **-or,** *s.* सभासद् *m.*, वृद्धसदस्यः.

Send, *v. t.* प्र-हि 5 P, सं-,प्रेष् c., सं-, प्रेर् c., विसृज् 6 P or c., (with acc. of place and dat. of person); 's. away' प्रस्था c. (स्थापयति), विसृज्; 's. for' आह्वे 1 P, आनी c.; आगम् c., आह्व c., 's. for a doctor' भिषजमाह्वातुं कमपि प्रेषय; 's. forth' नि-प्र-सृ c., उदीर् c., उत्क्षिप् 6 P, उद्यम् 1 P, उद्-गॄ 6 P; (as a missile) प्र-,मुच् 6 P, प्रक्षिप्, प्रास् 4 P. **-er,** *s.* प्रेषकः, प्रेरकः.

Senile, *a.* वृद्ध, जराजन्य. **-ity,** *s.* वृद्धत्वं, जरा, वार्धक्यं.

Senior, *a.* ज्येष्ठ, वरिष्ठ, ज्यायस्, वरीयस्, वर्षीयस्; (in age) कालज्येष्ठ, वयोज्येष्ठ; 's. in office' अधिकारज्येष्ठ. **-s.** ज्येष्ठः, अग्रजः, &c. 2 गुरुः, गुरुजनः, आर्य-वृद्ध-जनः. **-ity,** *s.* ज्येष्ठता, ज्यैष्ठ्यं, वरिष्ठता; वयोज्येष्ठता, &c., 'according to s.' अनुज्येष्ठं.

Sennight, *s.* सप्तरात्रं, सप्ताहः.

Sense, *s.* इंद्रियं, हृषीकं, विषयिन् *n.*, 's. s collectively' इंद्रियवर्गः-गणः, पंचेंद्रियं; 's. s of perception or knowledge' ज्ञानेंद्रियाणि; 's. s of action' कर्मेंद्रियाणि, करणानि, कर्मसाधनानि; 'evident to the s.' प्रत्यक्ष, इंद्रिय-ग्राह्य-गोचर; 'pleasures of s.' विषय-इंद्रिय-सुखं, 'object of s.' विषयः, इंद्रियार्थः, इंद्रियविषयः. 2 उपलब्धि *f.*, वेदनं-ना, बोधः, ज्ञानं, अनुबोधः, ग्रहणं, संवेदनं, इंद्रियबोधः-ग्रहणं. 3 बुद्धि *f.*, मति *f.*, धीः, चित्तशक्तिः, प्रज्ञा; *See* **Intellect.** 4 चेतना, संज्ञा, चैतन्यं; ज्ञानं, बोधः, अनुभवः, संवेदनं; 's. of obligation' कृतज्ञता, कृतवेदित्वं; 's. of pleasure' सुखबोध-अनुभवः; 'come to s. s', 'recover one's s. s' संज्ञां-चेतनां लभ् 1 A or आ-प्रति-पद् 4 A, प्रकृतिं आपद्, प्रकृतिस्थ-*a.*-भू 1 P; 'loss of s. s' मतिभ्रंशः, बुद्धि-मति-नाशः, विप्लवः; 'common s.' विवेकः; 'good s.' सुबुद्धिः, सद्भावः; सौजन्यं; 'out of s. s' विगतचेतन, लुप्तसंज्ञ, नष्ट-हत-ज्ञान, बुद्धिभ्रष्ट, नष्टेंद्रिय-बुद्धि;

'who has lost all s. of honour and dishonour on account of old age' जरावलुप्तमानावमानचिन्तः. 5 मतं,अभिप्रायः, उद्देशः, आशयः, आकांक्षा. 6 अर्थः, भावः (purport): 'understanding the literal s.' शाब्दबोधः; 'literal s.' शब्दार्थः; अक्षरार्थः; 'in its true s.' अन्वर्थ-यथार्थ-*a.*, यथार्थतः, परमार्थतः,अर्थतः; 'else this repetition has no s.' अन्यथा एषा वीप्सा न चरितार्था भवति (Ka. 320), निरर्थिका भवेत् &c.; *See* **Significant.** **-ible**, *a.* इंद्रियगोचर-ग्राह्य-गम्य-ज्ञेय, प्रत्यक्ष. 2 विषय-इंद्रियार्थ-ग्राहिन्, ग्रहणसमर्थ. 3 अभिज्ञ, ज्ञ, वेदिन् in comp.; 's. of your service' त्वत्सेवाभिज्ञ; उपकारज्ञ-वेदिन् 's of obligations'. 4 संज्ञावत्, चेतनोपपन्न, सचेतन,चेतन, चेतनावत्, वेदनज्ञान-क्षम;लब्ध or प्राप्त-संज्ञ or चैतन्य,आपन्नचेतन 5 मति-बुद्धि-मत्, सज्ञान, ज्ञानवत्, विवेकिन्, ज्ञान-बुद्धि-शालिन्, मनस्विन्, धीसंपन्न; *See* **Rational** also. 6 विचक्षण, सुधी, सुमेधस्, प्राज्ञ. 7 उपपन्न, युक्त, उचित, संगत, समंजस, सयुक्तिक, युक्तिपूर्व. **-ibility,** *s.* ग्रहणसामर्थ्य-शक्ति *f.* 2 सूक्ष्म or शीघ्र-चैतन्यं or बोधः; वेदनं-ना, बोधः, ज्ञानं, अनुभवः, चेतना; चैतन्यं; संज्ञा. **-ibly,** *adv.* प्रत्यक्ष-क्षतः, &c. 2 सुबुद्ध्या, सुबुद्धिपूर्वं, बोध-ज्ञान-पूर्वं, चेतनवत्, अभ्रमेण. **-less,** *a.* अचेतन, विषयग्रहणाक्षम. 2 अ-वि-गतचेतन, निःसंज्ञ, लुप्तसंज्ञ, नष्टचैतन्य, लुप्तबुद्धि, संज्ञा-चैतन्य-हीन. 3 दुर्बुद्धि, मति-बुद्धि-हीन, मूढ, मूर्ख, अनात्मज्ञ, निर्बोध; *See* **Foolish.** 4 अयुक्त, असमंजस, अनुपपन्न, अनुचित. 5 निरर्थक, असंगत, असंबद्ध. **-lessly,** *adv.* मूर्खवत्, मूढवत्, &c. **-Sensitive,** *a.* सचेतन, चेतनावत् विषयग्रहणक्षम-समर्थ. 2 सूक्ष्म or शीघ्र or वेदिन् or ग्राहिन्,शीघ्रचेतन; चलेंद्रिय, अनायासेन संक्षोभ्य, मृदुप्रकृति, कोमलहृदय. 3 लज्जालु, लज्जावत्; *See* **Modest;** 's. plant' लज्जालुः,नमस्कारिन् *m.* **-ly,** *adv.* शीघ्रज्ञानेन,सूक्ष्मचैतन्येन. **-ness,** *s.* सूक्ष्मचैतन्यं, शीघ्रबोधः, &c. **-Sensual,** *a.* इंद्रिय, विषय in comp.; 's. pleasures' विषयसुखानि, इंद्रियोपभोगः, विषयासक्ति *f.* 2 (Of persons) इंद्रियसुखनिरत, विषयासक्त, विषयपरायण- पर-निरत-अधीन-वश, इंद्रियवश, &c.; विषयिन्, विषयोपसेविन्, विषयसुखासक्त, भोग-कामआसक्त. **-ist,** *s.* विषयिन् *m.*, विषयासक्तः, भोगासक्तः; *See* above. **-ity,-ness,** *s.* विषयासक्तिः, इंद्रियसुखोपभोगः, विषयवशता-परायणता &c., भोगासक्तिः, कामासक्तिः, इंद्रिय-विषय-सुखनिरतिः. **-Sentient,** *a.* सचेतस्, सचेतन, चेतनावत्, चैतन्य-प्राण-विशिष्ट; *See* **Sensible:** 'a s. being' प्राणिन् *m.*, देहिन् *m*, शरीरिन् *m.* जीवः, प्राणभृत् *m.*,चेतनः. **-Sensation,** *s.* प्रत्यक्षं. 2 सं-,वेदनं-ना,बोधः, ज्ञानं,उपलब्धिः, चेतना, प्रत्यक्षज्ञानं, अनुभवः. 3 विकारः, विक्रिया; 'produced a great s. among the people' जनमनांसि भृशं समक्षोभयत्-आकुलीचकार.

Sensorium, *s.* मस्तिष्कं, मस्तिकं, गोर्दं, गोदं.

Sensory, *a.* संवेदक-यितृ.

Sentence, *s.* निर्णयः, दंडाज्ञा, दंडादेशः, आधर्षणं; 's. of death' प्राणदंडाज्ञा. 2 विचारः, निश्चयः, निर्णयः, संकल्पः. 3 वाक्यं, वचनं, उक्ति *f.*, वचस् *n.*, पदसमूहः. 4 सूत्रं. *-v. t.* दंडं आदिश् 6 P or निर्णी 1 P or कथ् 10 U. निविद् c.; 's. ed him to death' तस्य वधदंडमादिशत्, वध्यतामसौ इति आज्ञापयत्. **-Sententious,** *a.* लाघवयुक्त, लाघवगुणोपेत, सूत्रमय (यी *f.*), सूत्रप्राय.

Sentiment, *s.* मतं, अभिप्रायः, बुद्धि *f.*, मति *f.* 2 संकल्पः, कल्पना. 3 अर्थः; *See* **Sense, Idea.** 4 भावः, रसः, रागः; 's. of love' शृंगाररसः; करुणारसः &c. **-al,** *a.* रसिक, रसमय (यी *f.*), सरस, रसात्मक, सराग, रसभूयिष्ठ. 2 काल्पनिक (की *f.*), भाविन.

Sentinel, Sentry, *s.* रक्षिन् *m.*, रक्षापुरुषः, रक्षकः.

Separate, *v. t.* वियुज् 7 A,10, वि-,रह् 1 P, 10 (रहयति), विनाकृ 8 U, (with instr.); 'Rati s-ed from Madana' मदनेन विनाकृता रतिः. 2 पृथक् कृ, विश्लिष् c., वि-, भिद् 7 P or c. विभज् 1 U, विच्छिद् 7 P, विघट् c.. विगम् c. (गमयति); व्यासंज् c., व्यतिरिच् 7 P or c.; (distinguish between) विविच् 3, 7 U, विशिष् 7 P or c.; 's-ing milk from water' दुग्धजलभेदविधिः. *-v. i.* पृथग्भू 1 P, विश्लिष् 4 P, विघट् 1 A, अपया 2 P, व्यप-इ 2 P, वियुज्-विच्छिद्-भिद्-pass.: 'the brothers have s. ed' विभक्ता भ्रातरः. *-a.* **-ed,** *a.* वि-,भिन्न, विभक्त, वियुक्त, विच्छिन्न; न जाने कियताध्वना विच्छिन्नमितो बलमनुयायि मे (Ka. 190) 'by what distance s.' &c.; पृथक् *ind.*,असंलग्न,असंसृष्ट,व्यतिरिक्त,व्यस्त. **-ion,** *s.* वियोगः, विरहः, विप्रयोगः,विश्लेषः, विभेदः, व्यतिरेकः, विच्छेदः, (with instr. for 'from'); भिन्नता, पार्थक्यं, पृथग्भावः. 2 पृथक्करणं, विभागः, वि-,भेदः-दनं, व्यासंगः, विगमः, विघटनं; विवेकः; 'afflicted by s.' विरहातुर, विरहपर्युत्सुक, विधुर. **-ly,** *adv.* पृथक्, वि-,भिन्नं; 'taken s.' एकैक-*a.*, व्यस्त-*a.*; सर्वाविनयानामेकैकमप्येषामायतनं (Ka. 103), तदुत किं व्यस्तमपि विलो- [illegible] v. 72) 'even one, taken s.' [illegible] **-ness,** *s.* पृथग्भावः, पार्थक्यं.

-Separable, *a.* विभाज्य, वियोज्य, विच्छेद्य; 'not s.' नित्यस्थायिन्, नित्य, प्रकृतिस्थ.

Sepals, *s.* विलयनं, द्रुतीभवनं.

Septangular, *a.* सप्तकोण, सप्तास्र.

September, *s.* भाद्रपदाश्विनं.

Septenary. *s.* सप्तकं. *-a.* सप्तन्.

Septennial, *a.* सप्तवार्षिक (की *f.*).

Septic,-al, *a.* विलयनकारिन्.

Septilateral, *a.* सप्तभुज, सप्तपार्श्व.

Septagenarian, *a.* सप्ततिवर्षीय.

Septum, *s.* महाबीजं, विटपः.

Sepulchre, *s.* समाधिः, प्रेतवासः, श्मशानं शवस्थानं-मंदिरं-गर्तः. **-Sepulchral,** *a.* (*s.* in comp. **-Sepulture,** *s.* निखननं, भूमौ निगूहनं 2 प्रेतकर्मन् *n.*-क्रिया; *See* **Funeral.**

Sequel, *s.* उत्तरं, उत्तरभागः, शेषः, शेषभागः, परिशिष्टं. 2 परिणामः, अंतः.

Sequence, *s.* अनु-,क्रमः, अन्वयः, आनुपूर्व्यं, परंपरा.

Sequester, Sequestrate, *v.* वियुज् 7 A, 10, पृथक् कृ 8 U. 2 **Seclude,** q. v. **-ed,** *a.* विविक्त; *See* **Secluded.**

Seraglio, *s.* अंतःपुरं, अवरोधः, शुद्धांतः, अंतर्गृहं; *See* **Harem.**

Seraph, *s. See* **Angel.**

Sere, *a.* शुष्क, म्लान, विशीर्ण.

Serene, *a.* प्र-,शांत, प्रसन्न, अक्षुब्ध, स्तिमित, स्थिर, निरुद्वेग; निराकुल, अनुद्विग्न; (sky) निरभ्र, वितिमिर, प्रसन्न; (water) विशद, स्वच्छ, शुद्ध, निर्-वि-अ-मल, प्रसन्न. **-ly,** *adv.* प्रसन्नं, सप्रसादं, शांत-प्रसन्न-चेतसा. **-ity,-ness,** *s.* प्रशांति *f.*, प्रसादः, अनुद्वेगः, असंभ्रमः, अक्षोभः, प्रसन्नता, निरभ्रता, निर्मलता.

Serf, *s.* दासः, कृषकदासः. **-dom,** *s.* दास्यं, दासवृत्ति *f.*

Seriatim, *adv.* यथाक्रमं, अनुपूर्वशः, अनुक्रमशः, आनुपूर्व्येण.

Series, *s.* माला, परंपरा, राजिः, श्रेणिः-णी, आवलिः-ली, पंक्तिः, (all *f.*); दामन् *f. n.*, पर्यायः, परिपाटि-टी *f.*, आनुपूर्वी-र्व्यं. **-Serial,** *a.* क्रमिक, यथाक्रम, क्रमानुसारिन्.

Serious, *a.* ग(गं)भीर, धीर; गंभीरवृत्ति-शील-स्वभाव; धीरदर्शन-स्वभाव; 'a s. look' धीरविलोकितं. 2 गुरु, अलघु, अनुपेक्ष्य, अनतिपात्य, दुर्धर्ष. 3 अपरिहासिन्, अविनोदशील; 'this is in truth, a s. matter' न खलु अयं परिहासस्य विषयः (Mal. 9); *See* **Earnest.** **-ly,** *adv.* गंभीरं, धीरं, सधैर्यं, गौरवेण. 2 अपरिहासेन, सत्यं; 'I tell you s.' न परिहसामि, नायं विनोदः, न परिहासः. **-ness,** *s.* गांभीर्यं, धीरता, धैर्यं, गौरवं, गुरुता; अपरिहासः, अविनोदः &c.

Sermon, *s.* धर्मोपदेशः, धर्मव्याख्यानं.

Serous, *a.* मेदस्विन्, मेदुर.

Serpent, *s.* सर्पः, भुजगः, भुजंगः-गमः, अहिः, पन्नगः, नागः, उरगः; *See* **Snake.** **-ine,** *a.* (*s.*) in comp.; वि-,सर्पिन्, वक्र, कुटिल; 's. course' भुजंगगतिः, वक्रा-कुटिला-गतिः.

Serpigo, *s.* दद्रुमंडलं, मंडलकुष्ठं.

Serrate,-ed, *a.* करपत्रनिभ, क्रकचतुल्य, अनुक्रकच, क्रकचधार, दंतुर, सच्छेद.

Serried, *a.* संहत, संश्लिष्ट.

Serum, *s.* मेदस् *n.*, वसा, वपा

Serve, *v. t.* सेव् 1 A, श्रु desid. (शुश्रूषते), उपास् 1 A, उप-स्था 1 A, उपचर् 1 P, परि-अनु-चर्; 'he who s. s not another's will' परेच्छानुरूपं न वर्तते, परच्छंदानुवर्ती न भवति, अन्यभावं न अनुप्रविशति. 2 अनुवृत् 1 A, अनुरुध् 4 A, अनुवि-धा 3 U; *See* **Obey.** 3 उपकृ 8 U, अनुग्रह् 9 P, उपचर्, साहाय्यं कृ; श्रेयः-सं-पद् c. 4 (अर्थं) साध् c., प्रवृत् c., सं-पद् c., निर्वृत् c. 5 पर्याप्त-उचित-*a.* भू 1 P, अलं with dat. or inf., क्लृप् 1 A (with dat.); 'this will s. to rouse his anger' तस्य कोपमुद्दीपयितुं-कोपोद्दीपनाय-अलं or पर्याप्तमिदं 6 उप-परि-क्लृप् c., उप-स्था c. (स्थापयति). 7 स्थाने-भूमौ-वृत् or भू or प्रयुज् pass. 8 प्र-उप-युज् 7 U, 10, विनि-युज्, निक्षिप् 6 P. 9 वृत्, आचर्, व्यव-हृ 1 P, (with loc. of person); *See* **Act, Behave;** 's. the purpose of', 's. as' उपयोगं व्रज् 1 P, स्थाने-भूमौ-भू; भूर्जत्वचः व्रजंति विद्याधरसुंदरीणामनंगलेखक्रिययोपयोगं (K. I. 7) 's. as love-letters' &c.; 's. up meals' परिविष् c., अन्नं उप-स्था c.; 'the Gods s. ed up food' मरुतः परिवेष्टारः आसन्; 's. out' प्रतिकृ, वैरं &c. निर्यत् 10. *-v. i.* सेवां-कार्यं-कृ; नियोगमनुष्ठा 1 P; कार्यं संपद् c.; 'this will s. as water to wash his feet with' इदं पादोदकं भविष्यति (S. 1). **-ant,** *s.* भृत्यः, सेवकः, किंकरः, अनु-उप-जीविन् *m.*, दासः, चेटः, प्रेष्यः, अनु-परि-चरः, परिजनः, परिचारकः, नियोज्यः, भुजिष्यः, शुश्रूषकः, उपासकः, सेवाजीविन् *m.*, वैतनिकः, भृतिभुज् *m.*, भरण्यभुज् *m.*, भृतकः; कर्मक(का)रः, (labourer); 'female s.', 's.-maid' चेटी, दासी, भुजिष्या, प्रेष्या, कर्मकरी, सैरं(रिं)ध्री. **-Service,** *s.* सेवा, शुश्रूषा, उपचारः, उप-परि-चर्या, उपासनं-ना; आ-सं-श्रयः; 's. of kings' नृपसंश्रयः, राजाश्रयः. 2 (State) दास्यं, दासवृत्ति *f.*, प्रेष्य-भृत्य-भावः, सेवा; 'he lives in my s.' स मामनुजीवति, मदाश्रितः. 3 अनुवर्तनं, अनुवृत्तिः, आराधनं; *See* **Obedience.** 4 वृत्तिः, नियोगः, कार्यं, व्यवसायः; व्यापारः, कर्मन् *n.*, व्यवहारः. 5 उपकारः, साहाय्यं, उपकृतं-ति *f.*, अनुग्रहः, हितं, अर्थः. 6 उपयोगः, व्यवहारः. 7 सपर्या, उपासना, पूजा, उपचारः, पूजोपचारः. 8

भोजनपात्रगणः; 'I am entirely at your s.' सर्वथा त्वदधीनोऽस्मि, भवता यथेच्छं नियुज्यतामयं दासः; 'in whose s. are you' कस्य सेवया जीवसि, केन नियुक्तस्त्वं; 'to keep in s.' सेवायां नियुज् 7 U, 10, (कर्मणि) व्याप् c. **-able,** *a.* उपयुक्त; उपयोगिन्, उपकारिन्, सहायभूत, प्र-उप-योज्य. **2** कार्यक्षम, कर्मकुशल, अलंकर्मीण. **-ably,** *adv.* सोपयोगं, सलाभं, सोपकारं. **-Servile,** *a.* दासेय (यी *f.*), दासोचित, दास-दास्य in comp.; 's. state-दासभावः, दास्यं, प्रेष्यभावः, दासवृत्तिः. **2** अतिचाटुपर, अत्यनुरोधिन्, श्ववृत्ति, अतिलालनपर. **-ity,** *s.* दास्यं, दास्यभावः. **2** चरणावपातः, श्ववृत्तिः, अतिलालनं, अत्यनुरोधः, छंदोऽनुवर्तनं. **-ly,** *adv.* दासवत्, अत्यनुरोधेन, अतिलालनपूर्वं. **-Servitor,** *s.* सेवकः, भृत्यः, &c.; *See* **Servant. -Servitude,** *s.* दास्यं, भृत्यभावः, किंकरत्वं, सेवा, प्रेष्यभावः, श्ववृत्तिः, सेवाधर्मः. सेवकदशा.

Sesame, Sesamum, *s.* तिलः, सारालः, सुगंधः; 'sowed with s.' तिल्य.

Session, *s.* उपवेशनं; 'sacrificial s.' सत्रं; 's. judge' दंडाधिकरणिकः. **2** (Time) सत्रकालः, कार्यनिर्वाहकालः.

Set, *s.* अस्तमयः, अस्तमनं, अस्तः. **2** जातं, जाति *f.*, गणः, संघः, श्रेणी, पंक्ति *f.*, समूहः, संयोगः; 's. s of ornaments fitting all parts of the body' सर्वांगिका आभरणसंयोगाः (Mal. 6). **3** (Of persons) वर्गः, गणः, संघः. **-v. t.** आ-नि-धा 3 U. वि-,न्यस् 4 P, स्था c.; (स्थापयति), निविश् c., अवरुह् c.; oft. by कृ 8 U, दा 3 U, ऋ c. (अर्पयति), (in the ground) रुह् c., निखन् 1 P. **2** प्र-परि-कल्प् c., व्यव-स्था c. **3** प्रणि-धा, प्रतिबंध् 9 P, (यदिमणिस्त्रपुणि प्रतिबध्यते P. I. 1), उत्-,खच् 10 (खचयति), अनु-व्यध् 4 P; 's. with jewels' रत्नानुविद्ध. **4** नि-,शो 4 P, उत्-,तिज् c., तीक्ष्णीकृ. **5** युज् 7 U, 10, सं-आ-°, समाधा, सं-,वि-धा (limb &c.); 's. one's foot in' पदं कृ (lit. and fig.). करिष्यसि पदं पुनराश्रमेऽस्मिन् (S. 4), कृतं मे वपुषि नवयौवनेन पदं (Ka. 137), 's. a trap' पाशं युज्; 's. in motion' चल् c., संचर् c., ईर् 10.; 's. the heart on' मनः-धियं-चित्तं, &c. (• **Mind,** q. v.) बंध् or आ-धा or संनि-विश् c. or युज्, आसक्त-*a.* भू 1 P (with loc.); 's. your heart on religious duties' आधीयतां धर्मे धीः (Ka. 63): 's. not your heart on transient objects' विनाशधर्मसु विषयेषु मनो मा संनिवेशय, विनाशिविषयासक्तो मा भूः; 's. the teeth on edge' दंतहर्षं जन् c.; 's. right', 's. in order' समीकृ, व्यव-स्था c., विन्यस्, विरच् 10; 's. to rights' प्रति-,समा-धा, सुस्थीकृ; प्रतियुज्, (प्रतियोजयितव्यवल्लकी R. VIII. 41); 's. free' मुच् 6 P or c.; *See* **Free;** 's. at naught' तृणाय-तृणवत्-मन् 4 A, तृणीकृ; ex. also by का मात्रा-गणना; 's. to music' स्वर-ताल-बद्ध-*a.* कृ. **-v. i.** अस्तं गम्-व्रज् 1 P or या-इ 2 P, अस्ताचलं-अस्तशिखरं-अवलंब् 1 A or प्राप् 5 P, सागरे मस्ज् 6 P. **2** संहन्-बंध्-pass. **-about,** आरभ् 1 A, प्र-वृत् 1 A. **-against,** विरुध् 7 U, प्रत्यव-स्था c., प्रतियुध् c.; *See* **Oppose. -apart,** पृथक् रक्ष् 1 P or स्था c., पृथक् कृ. **-aside,** अपाक्षिप् 6 P, मुच्, त्यज् 1 P, oft. by आस् 2 A, स्था 1 P; 's. aside that point' आस्तां-तिष्ठतु-तावद्दूरे स विषयः; *See* **Reject, Omit. -before,** उप-स्था c., उपानी 1 P, उपाहृ 1 P; 's. food before a person' परिविष् c. **-down,** न्यस्, भूमौ न्यस् or नि-धा. **2** आ-अधि-क्षिप्, भर्त्स् 10 A, अपकृष् 1 P, अवमन् c., अव-ज्ञा 9 U. **3** गण् 10, मन् 4 A. **4** (In writing) लिख् 6 P, निर्दिश् 6 P. **-forth,** उपनि-विनि-अस्, वर्ण् 10, उपक्षिप्, निर्दिश्, अभि-धा. **-forward,** प्रया, प्रगम्, प्रसृ: (*v. t.*) पुरस्कृ, उन्नम् c., वृध् c. **-in,** समुपा-गम्, उप-स्था, प्रवृत्, अवतृ 1 P; 'summer which has just s. in' अचिरप्रवृत्तं ग्रीष्मसमयं (S. 1), वसंतावतारसमये &c.; (*v. t.*) अंतर् ग्रह् 9 U. **-off, Set out,** q. v.; (*v. t.*) क्षुभ् c., प्रकाश् c.;शोभां पुष् 4,9 P लक्ष्मीं तन् 8 U, (मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति S. 1.); oft. by शुभ् 1 A, गुणा विनयेन शोभंते 'are s. off by modesty'; 's. off against' तुल् 10 (तुलयति), प्रतिगण्. **-on,** प्रवृत् c., प्रयुज्, (अथावमानेन पितुः प्रयुक्ता K. I. 21), प्रेर्, प्रोत्सह् c.; *See* **Prompt;** 's. on foot' प्रति-ष्ठा c., प्रवृत् c., आरभ्; 's. on fire' दह् c., ज्वलनाय ऋ . or विसृज् 6 P; 's. on guard' अवहित *a.* कृ. **-out,** प्र-स्था 1 A, प्र-या, प्रगम्, प्रचल्, निर्गम्. **-over,** नियुज्, अधिकृ, अधि-ष्ठा c. **-to,** मनः बंध् or युज् or निविश् c., आसक्त-*a.* भू; 'they s. to their work' कार्यव्यापृता बभूवुः &c., **-up,** बंध्, उत्था c.; सं-अव-प्रति-स्था c.; *See* **Raise,** 'the people s. up a howl' बहुकोलाहला जनाः; उत्थितो निनादः 'a scream was s. up'; (*v. i.*) वृत्तिं-व्यवहारं-आरभ् or प्रवृत् c.; 's. up for' अभिमन् 4 A; *See* **Pretend, Profess.-upon,** आक्रम्, आ-अव-स्कंद् 1 P, सहसा ग्रह्. **-a.** नियत, परिकल्पित, एकरूप; विन्यस्त, सुविरचित. **2** स्थापित, न्यस्त, निहित, निवेशित

&c. 3 खचित, छुरित, अनुविद्ध, प्रणिहित, प्रतिबद्ध, प्रयुक्त, करंब, करंबित. **-ter,** *s.* योजयितृ *m.*,प्रतिष्ठापकः, &c.2 मृगयाकुक्कुरः, विश्वकद्रुः. **-ting,** *s.* योजना, सन्निवेशः, स्थापनं-ना, अर्पणं, रोपणं, &c. **2** अस्तमनं, अस्तं. **-Set-down,** *s.* अपकर्षणं, अभिभवः, मानखंडनं. **-Set-off,** *s.* परिवर्तः, तुल्यमूल्यं वस्तु.

Setateous, *a.* शूकयुक्त, बहुशूक.

Settle, *v. t.* स्था c. (स्थापयति), प्रति-अव-°, नि-आ-वश् c. **2** सं-व्यव-स्था c., व्यवसो 4 P, निर्-अव-धृ 10, संकल्प् c., साध् c.; 's. ing what to say' व्यवस्थापितवाक्, वाचं व्यवस्थाप्य; अस्याः पितुः समीपनयनमवस्थितमेव (S. 5) 'is but s. ed &c.' **3** (Lands &c.) दा 3 U, युज् 10 (with instr. of grant); त्वां शासनशतेन योजयिष्यामि (P. I. 4). **4** अधिवस् c. **5** स्थिरीकृ 8 U, स्वस्थ-निर्वृत-*a.* कृ. **6** प्र-,शम् c. (शमयति), सं-धा 3 U, समा-धा. **7** सं-,वि-धा, वि-,रच्, विन्यस् 4 U; 's. in marriage' निविश् c., (तनयं निवेश्य S. 4); 's. a debt' ऋणं शुध् c. or अपाकृ. **8** अधः पत् c. or गम् c., अव-सद् c. **-v. i.** अव-व्यव-स्था 1 A, स्थिरीभू 1 P, निवासं स्थिरीकृ. **2** प्रशम् 4 P, विश्रम् 4 P. **3** तले पत् 1 P, सद् 1 P, अव-नि-°, अधः गम् 1 P; प्रसद् (for becoming clear). **4** अधः पत् c. **5** घनीभू, संहन् pass., संहतीभू; 's. ed amongst themselves' मिथः प्रशमं याताः, परस्परसंधानमकुर्वन्; 's. in life' विवह् pass., निविश् 6 A (संसारपथं), विवाहं कृ, प्रतिष्ठित-*a.* भू. **-ed,** *a.* स्थापित, रोपित, प्रतिष्ठित &c. **2** नियत, निश्चित, निर्णीत, व्यवस्थित, सिद्ध, निष्पन्न. **-ing,-ment,** *s.* स्थापनं, सं-प्रति-अव-°. **2** निर्णयः, निश्चयः, निर्धारणं-णा, अवधारणं **3** सं-धानं, प्र-,शमः-मनं, संधिः, समाधानं. **4** अधिवासनं. **5** अधिवासितदेशः; 's. in life' विवाहः, संसारप्रतिष्ठा; 'marriage-s.' शुल्कः-ल्कं. **-er,** *s.* अधिवासिन् *m.*

Seven, *a.* सप्तन्. **-fold,** *a.* सप्तगुणं. **-adv.** सप्तधा, सप्तगुणं. **-th,** *a.* सप्तम (मी *f.*). **-Seventeen,** *a.* सप्तदशन्. **-th,** *a.* सप्तदश (शी *f.*,). **-Seventy,** *a.* सप्तति *f.*

Sever, *v. t.* अव-वि-च्छिद् 7 P or c., अवकृत् 6 P or c., वियुज् 7 A, 10, विश्लिष् c., विभिद् c. **-al,** *a,* भिन्न, पृथक् in comp., पृथगात्मकं. **2** अनेक, बहु; *See* **Many.** **3** स्व, आत्म in comp. **4** स्व-स्व; *See* **Respective.** **-ance,** *s.* विच्छेदः, विश्लेषः, विभेदः, पृथक्करणं. **-ally,** *adv.* पृथक्, पृथक् पृथक्, प्रत्येकं, अवयवशः, व्यक्तिशः. **-alty,** *s.* भिन्नता, पार्थक्यं, पृथग्भावः.

Severe, *a,* खर, परुष, तीक्ष्ण, निष्ठुर, कठोर, चंड, तीव्र, उग्र, असौम्य, उग्रशासन, तीक्ष्णदंड. **2** (Of things only) दुःसह, दुर्विषह; तुमुल, घोर, (of fight); अत्यंत, अतिमात्र; दु-अति pr. **-ity,** *s.* पारुष्यं, कठोरता, नैष्ठुर्यं, काठिन्यं, उग्रदंडता; तीव्रता, दुःसहता, &c. **2** तीक्ष्णदंडः. **-ly,** *adv.* परुषं, कठोरं, निष्ठुरं, उग्रं, तीव्रं, तीक्ष्णं, चंडं,बलवत्.

Sew, *v. t.* सिव् 4 P, वि-नि-° (together); वे 1 P, प्र-वि-°. **-ed, Sewn,** *a.* स्यूत-न, उत, प्रोत. **-ing,** *s.* सीवनं, सेवनं, स्यूति *f.*

Sewer, *s.* प्रणाली-लः, परि(री)वाहः, जलोच्छ्वासः, मलनिर्गमः, संकरः, मलपथः.

Sex, *s.* Ex. by स्त्री or पुंस्-पुरुषः ('Man' q. v.), द्वंद्वं, मिथुनं. **2** जाति *f.*, लिंगं; 'the male s.' पुंजातिः; स्त्रीजातिः &c. **-ual,** *a.* स्त्रीपुंस, स्त्रीपुरुष in comp.; 's. intercourse' सु-,रतं, मैथुनं,: संगमः, व्यवायः, संगः, संभोगः.

Sexagenarian, *s.* षष्टिवर्षीय

Sexangular, *a.* षडस्र, षट्कोण.

Sexennial, *a.* षड्वार्षिक (की *f.*).

Sextant, *s.* वृत्तषड्भागः.

Shabby, *a.* कुत्सित, कृपण, तुच्छ, निंद्य, अपकृष्ट, अधम, जघन्य; *See* **Mean.** **2** मलिन; सुव्यवरिष्ठ, जर्जरित,पाश in comp. **-ily,** *adv.* कुत्सितं, कृपणं, मलिनं. **-iness,** *s.* कार्पण्यं, मालिन्यं &c.

Shackle, *s.* निगडः, शृंखला-लः, बंधनं, पाशः. **-v. t.** निगडैः बंध् 9 P or संयम् 1 A; *See* **Fetter.**

Shade, *s.* छाया, in all senses; 'the dense s. of sugarcanes' इक्षुच्छायं, 'full of s.' प्रच्छायं; अनातपः, अप्रकाशः, निरातपस्थानं. **2** अंधकारः, तिमिरं, तमस् *n.* **3** व्यवधा-धानं, तिरस्करिणी, वितानं. **4** क्रमः, भागः. **5** **Ghost,** q. v.; 's. of difference' सूक्ष्मभेदः, स्वल्पांतरं; 's. of meaning' अर्थस्य सूक्ष्मभेदः; 'like a picture with all its s. s painted by a pencil' उन्मीलितं तूलिकयेव चित्रं (K. I. 32); cast into s.' तिरस्कृ 8 U, प्रत्यादिश् 6 P; *See* **Back-ground.** **-v. t.** छद् 10, प्र-आ-°, वितन्, 8 U. **2** आतपं निवारय् 10, अनातप-*a.* कृ. **-y,** *a.* प्रच्छाय, सच्छाय, छायाबहुल-आवृत-युक्त-सनाथ; निरातप, आतपरहित, छाया in comp.; 'a s. tree' छायावृक्षः. **-Shadow,** *s.* छाया, प्रतिच्छाया, प्रतिबिंबं, प्रतिमा, प्रतिरूपं, प्रतिमूर्ति *f.* **2** आश्रयः, शरणं. **3** तमस् *n.*, अंधकारः; 'deep s. s' गाढतमः पटलानि. **4** गंधः, लेशः, आभासः. **-v. t.** प्र-आ-च्छद् 10. **2** आभासं दृश् c., प्रतिबिंबयति (D.). **-y,** *a.* छायारूप, असार, छायात्मक, अवास्तविक (की *f.*), मिथ्या-मृषा in comp. **2** अंधु-

च्छाय, मंदकांति-प्रभ, मंद-न्यून-तेजस् ; *See* **Dim, Faint.**

Shaft, *s.* कांड: (of arrows) **2** बाण:, शर:, इषु:; *See* **Arrow;** शल्य:-ल्यं. **3** दंड:; (of a carriage) धुर् *f.*, कूबर:; (of a plough) . ईषाशा; (of a mine) कूप:, गर्त:, अवट:.

Shag, *s.* दृढ-स्थूल-लोमन् *n.* **-gy,** *a.* लो-(रो)मश, लोमावृत, स्थूललोमन्. **2** रूक्ष, मलिन.

Shake, *v. i.* प्र-,कंप्-वेप्- 1 A, वि-प्र-चल् 1 P, वेल्ल् 1 P, सं-प्र-क्षुभ् 4 P, 1 A; (fig.) अभिभू-बाध्-pass. **-***v. t.* कंप् c., धू 5. 9 U, 6 P, वि-आ-°, चल् c., सं-वि-प्र-°; क्षुभ् c.; ध्वानेन सर्वतः प्रचालितमिव तदरण्यमभवत् (Ka. 29) 'was, as if, s. en by the sound'. **2** अभिभू 1 P, आकुलीकृ 8 U; 'this position would be s. en' इति प्रतिपादितमाकुलीभवेत् (S. B. 335); 's. one's confidence' साशंक-शंकान्वित-*a.* कृ; 's. about' प्रेंख् c., आंदोलयति (D.); 's. off' निर्धू, निरस् 4 U, निराकृ, अपास्, त्यज् 1 P, अपानुद् 6 P, प्रतिह् c.; *See* **Dispel;** 's. hands with each other' अन्योन्यं हस्तौ स्पृशत:. **-***s.*, **-ing,** *s.* कंप: धूननं, वि-,धु(धू)ति *f.*, विचलनं, वेपनं, सं-,क्षोभ:. **-ing,** *a.* चल, सकंप, चलन, लोल, तरल, चंचल, पारिप्लव. **2** क्षोभकारिन्. **-y,** *a.* अस्थिर, चल, लोल; *See* **Fickle.**

Shallow, *a.* गाध, उत्तान, अग(गं)भीर, गाधजल, अल्पजल; 's. knowledge' पल्लवग्राहि पांडित्यं; 's. person' अल्प-मति:-बुद्धि:, गाधज्ञान:. **-***s.* सैकतं, पुलिनं, गाधस्थलं.

Sham, *s.* व्यपदेश:, छद्मन् *n.*, व्याज:, छलं; *See* **Pretext.** **-***a.* छाद्मिक-कापटिक-(की *f.*) कपट-व्याज-कूट-मिथ्या in comp.; कृतक, अश्रद्धेय, अनृत. **-***v. i.* अप-व्यप-दिश् 6 P; *See* **Pretend.**

Shambles, *s.* शू(सू)ना, सौनस्थानं.

Shambling, *a.* वक्र, विरूप. **2** चंचल, चपल, विषम.

Shame, *s.* लज्जा, ह्री:, त्रपा, व्रीडा. **2** अप-मान:, दुष्कीर्ति *f.*, कलंक:, लज्जास्पदं, अकी-र्तिहेतु:; 'to feel s.' लज्ज् 6 A; 's., for s. !' धिक् (with acc.). **-***v. t.* 'put to s.' ह्री c. (ह्रेपयति); त्रप् c., व्रीड् c., लज्ज् c. **2** अपमन् c., कलं-कयति (D.); *See* **Disgrace.** **3** अवमन् 4 A, लघूकृ 8 U, अव-ज्ञा 9 U. **-ed,** 's.-faced' *a.* लज्जित, त्रपित, व्रीडित, लज्जा-व्रीडा-शील. **-ful,** *a.* लज्जाकर (री *f.*), ह्रेपण (णी *f.*), लज्जा-त्रपा-जनन (नी *f.*), अपकीर्तिकर, गर्ह्य. **-less,** *a.* निर्लज्ज, निर्व्रीड, निर्ह्रीक, अपत्रप, लज्जाहीन, त्यक्त-निरस्त-लज्ज, विघात, धृष्ट, अप्रतिभ. **-lessly,** *adv.* निर्लज्जं, लज्जां विहाय-विसृज्य.

Shampoo, *v. t.* संवह् c., मृद् 9 P or c. **-er,** *s.* संवाहक:. **-ing,** *s.* संवाहनं, अंगमर्दनं.

Shank, *s.* जंघास्थि *n.* **2** जंघा, दीर्घभाग:-अंश:; 'having long s. s' दीर्घजंघ, ऊर्ध्वज्ञु, ऊर्ध्वजानु.

Shanty, *See* **Hut.**

Shape, *s.* आकार:, रूपं, आकृति *f.*, मूर्ति *f.*, संस्कार:, संस्थानं. **-***v. t.* आकारं वि-धा 3 U or दा 3 U, रूप् 10, क्लृप् c., घट् c. (घट-यति), रच् 10. **-ed,** *a.* साकार, सरूप, रूपिन्, (*s.*) in comp.: 'moon-s.' चंद्राकृति &c. **-less,** *a.* निराकार, अमूर्त, निराकृति, अरूप. **2** अप-वि-कु-रूप. **-ly,** *a.* सुरूप, सुरेख, सुन्दराकार.

Shard, *s.* मृत्पात्रखंड.

Share, *v. t.* सं-विभज् 1 U. परिकल्प् c., अंश् 10, वंट् 10; अंशांशि दा 3 U; 'sorrow s. ed by dear friends' स्निग्धजनसंविभक्तं दु:खं (S. 3); 'with whom else shall I s. my grief' केन वान्येन सह साधारणीकरोमि दु:खं (Ka. 233). **2** भाजं-अंशं-हृ 1 P or लभ् 1 A or ग्रह् 9 U, अन्येन सह भुज् 7 A; 'the demons shall s. the labour of churning' दानवा अपि मंथनश्रमभाज: भवेयु:, (युष्माभि: सार्धं) मंथनश्रममनुभवेयु:, &c.; 's. ing equally pleasure and pain' समदु:खसुख. **-***s.* अंश:, भाग:, वंट:, उद्धार: (of an estate); 'he is to have a s.' अंशभाग्भवेत्; 'he has a s. in the plot' कपटप्रबंधे सहकारी असौ. **2** (Of a plough) फाल:, कुशी. **-er,** *s.* अंशहर:, अंशिन् *m.*, भागिन्-भाज् in comp. **-Share-holder,** *s.* अंशभागी, अंशग्राही, भागहारी-ग्राही.

Shark, *s.* ग्राह:, नक्र:, अवहार:, मकर:; (fig.) बकवृत्ति:, धूर्त:; *See* **Rogue.**

Sharp, *a.* तीक्ष्ण, in all senses; तीक्ष्णा बुद्धि:, तीक्ष्णा वर्षधारा, तीक्ष्णो दंड: &c.; नि-,शात, नि-,शित, प्र-,खर, तिग्म, तीव्र, तीक्ष्ण-शित-धार, सुनय, तीक्ष्णाग्र; 's. descending arrows' निशितनिपाता: शरा: (S. 1). **2** (Intellect) अतिप्रदीप्त, सूक्ष्म, तीक्ष्ण, सूक्ष्म-शीघ्र-ग्राहिन्; (of persons) तीक्ष्णमति, कुशाग्रबुद्धि-मति, सूक्ष्म-शीघ्र-तीव्र-मति, प्रदीप्तप्रज्ञ, विदग्ध, निपुण, पटु, चतुर, कुशल; (in action) शीघ्र, आशु-क्षिप्र-कारिन्, तीक्ष्ण-कर्मन्. **3** सरस, विदग्ध, रसिक. **4** अम्ल, शुक्त. **5** कटु, उग्र, (smell &c.) **6** कटु, उग्र, अति तीक्ष्ण, परुष, अरुंतुद, मर्मस्पृश्-भिद्; 's. pain' तीव्रवेदना; 's. language' परुषवचनं, वाग्गसि:; 's. sound' कर्कशध्वनि:; 's.-edged' तीक्ष्ण,

निशितधार, धारासनाथ; 's.-pointed' तीक्ष्णाग्र, सूच्यग्र; 's.-set' तीव्रक्षुधाग्रस्त, अतिप्रबलक्षुधावसन्न; 's.-shooter' लक्ष्यवेधिन्; 's.-sighted' तीक्ष्ण-सूक्ष्म-दृष्टि, &c. -s. उदात्तः;उदात्त-उच्च-स्वरः. -en, v.t. नि-, शो 4 P, उत्तिज् c., शाणयति (D.), तीक्ष्णीकृ 8 U, क्ष्णु 2 P: (appetite) उत्-,क्षुध् c. प्र-,वञ्च् c., दीप् c. -er, s. वंचकः, धूर्तः; *See* **Rogue.** -ly, *adv.* तीक्ष्णं, तीव्रं, प्रखरं, उग्रं, परुषं, &c. -ness, s. तीक्ष्णता, कुशाग्रमतित्वं, मतिप्रकर्षः, पाटवं, पारुष्यं, कार्कश्यं &c.

Shatter, v. t. वि-,शॄ 9 P, वि-,दॄ 9 P or c., खंडशः-लवशः-भंज् 7 P, लवशः चूर्ण् 10 or निष्पिष् 7 P; 'why am I not s. ed into a thousand pieces' दीर्यं किं न सहस्रधाहं (U. 6); यथा यथायं वैनासिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा विदीर्यत एव (S. B. 580) 'the more is this V. theory put to a logical test, the more is it s. ed to pieces (does it give way). -v. i. विदॄ &c. pass.

Shave, v. t मुंड् 1 P, 10, क्षुरेण कृत् 6 P or छिद् 7 P or लू 9 U, आवप् c., क्षुर्-खुर् 6 P. 2 तक्ष् 1, 5 P; *See* **Pare.** -er, s. क्षौरिकः, नापितः, क्षुरिन् m., मुंडकः. -ing, s. क्षौरं, मुंडनं. 2 तष्टं, विदलं, शकलं, खंडः.

She, *pron.* सा; in comp. ex. by f terminations, 's.-goat' अजा, 's.-sparrow' चटका &c.

Sheaf, s. (शस्य-)मुष्टि m. f., स्तंबः, गुच्छः, स्तबकः.

Shear, v. t. लू 9 U, कृत् 6 P, छिद् 7 P, आवप् c., मुंड् 1 P, 10, वि-,शॄ 9 P. 2 अपहृ 1 P, निर्हृ; 'shorn of' वीत, हृत, निर्, हीन in comp.; *See* **Destitute;** 'was shorn of his arms' छिन्नबाहुः कृतः or तस्य बाहू व्यशीर्येताम्. -er, s. लोमच्छिद् m.-च्छेदिन्, छिद् in comp. -ing, s. लवनं, कर्तनं, वपनं, छेदः-दनं. -Shears, s. खंडधारा, कर्तरिका, कर्तरी, कृपाणी.

Sheath, s. कोशः-षः, पिधानं, आधारः; आ-, वेष्टनं, पुटः-टं, आच्छादनं. 2 दलं. -Sheathe, v. t. कोशे नि-धा 3 U or निविश् c. 2 आ-परि-वेष्ट् 1 A or c., पि-धा, आवृ 5 U, आच्छद् 10.

Shed, v. t. नि-,पत् c., वि-,मुच् 6 P, or c., विसृज् 6 P, गल् c.: 's. tears' बाष्पं विसृ 1 P, अश्रूणि वि-,मुच् or पत् c. 2 (Blood) स्रु c., पत् c., मुच्, मोक्ष् 10; 's. influence' फल् 1 P; 'the moon s. s her white glory' इंदुर्धवलरश्मिजालं विकिरति. 3 (Light) क्षिप् 6 P, विसृज्, प्रकॄ 6 P, प्रसृ c. -s. शाला; 's. for cattle' गोशाला, गोष्ठं. -der, s. स्रावकः, मोचकः पातकः.

Sheen, a. उज्ज्वल, दीप्तिमत्; *See* **Bright.** -s. प्रभा, तेजस् n.

Sheep, s. मेषः, अविः, उरभ्रः, ऊर्णायुः; *See* **Ram;** 'a female s.' मेषी, एडका, 'goats and s.' अजाविकं; 'flock of s.' औरभ्रं. -ish, a. अप्रतिभ, लज्जाशील, जनभीत, निस्तेजस्, निष्प्रभ, हत-नष्ट-गत-वीर्य, मेषस्वभाव-शील.

Sheer, a. शुद्ध, केवल, मात्र in comp.; *See* **Bare, Mere.** -v. i. वि-,अपसृ-सृप् 1 P.

Sheet, s. उत्तरच्छदः, प्रच्छदः, प्रच्छदपटः-वस्त्रं, शय्याच्छादनं. 2 (Of paper) पत्रं, फलकं, खंडः, एकभागः. 3 पत्रं, फलकः-कं (s. of metal); 'winding-s.' प्रेत-शव-वस्त्रं; 's. of water' जलसंघातः, तोयराशिः.

Shelf, s. काष्ठफलकः.

Shell. s. कोशः-षः, कंचुकः, कवचः-चं, त्वच् f. (of fruit &c.): पुटः-टं; 'bivalve s.' कंबुः-बूः; 'conch-s.' शंखः; कंबुः; 'oyster-s.' शुक्ति f.; 'dealer in s. s.' शंखकारः, शांखिकः; कांबविकः, 's. of a pea' शिंबा, बीजकोशः; तुषः (of rice.) 2 आ-परि-वेष्टनं, पुटः, कोशः (envelope). 3 बहिर्भागः; 's.-cutter' कांबविकः; 's.-fish' कंबुस्थः, शंखस्थः. -v. t. कोषं-त्वचं &c. अपनी 1 P or निर्हृ 1 P, निस्त्वचीकृ 8 U. -y, a. शंखिन्, कंबुमय (यी f.),-पूर्ण.

Shelter, s. सं-आ-श्रयः, शरणं, निवासस्थानं. 2 रक्षणं, त्राणं; 'able to give s.' शरण्य; 'take s. with' आ-समा-श्रि 1 U, शरणं या 2 P or गम् 1 P, शरणार्थं या. -v. t. 'give s.' रक्ष् 1 P, त्रै 1 A; *See* **Protect;** प्र-,छद् 10, व्यव-धा 3 U; आश्रयं दा 3 U, शरणं भू; 's. ed from the wind' निर्वात. -less, a. निराश्रय, निरालंब, अशरण.

Shelve, v. i. अवसृप् 1 P, प्रवणीभू 1 P. -v. t. निष्कस् c., निराकृ 8 U. -ing, a. अवसर्पिन्, प्रवण.

Shepherd, s. अविपालः, मेषपालः. -ess, s. मेषपाली, मेषरक्षिणी.

Sherd, s. खंडः-डं, शकलः-लं.

Shew, v. t. *See* **Show.**

Shield, s. चर्मन् n., फलकः-कं, फलं; 'armed with a s.' चर्मिन्, फलकपाणि, फलभृत्; 'having sword and s.' खड्गचर्मधर. 2 आश्रयः, शरणं, रक्षणं, गुप्ति f. -v. t. रक्ष् 1 P, त्रै 1 A, आ-, छद् 10, *See* **Protect.**

Shift, s. उपायः, प्र-,युक्ति f., गति f., साधनं, प्रयोगः. 2 छलोपायः, कपटं; छद्मन् n., छलं, अप-व्यप-देशः. 3 अंतरीयं, अधोंशुकं, अधोवसनं. -v. i. परि-व्या-वृत् 1 A. 2 वि-,चल् 1 P, स्थानांतरं गम् 1 P or चल्.

3 वस्त्रांतरं परि-धा 3 U; 's. for oneself' वृत्तिं-जीविकां-उपपद् c. or प्रकल्प् c. **-v. t.** परि-व्या-वृत् c., अन्यथा कृ 8 U, विकृ. **2** विचल् c., स्थानांतरं गम् c. or चल् c. **-y,** *a.* छल-कपट-प्रिय.

Shilly-Shally, *s.* अनवस्था, अनिश्चयः, द्वैधीभावः.

Shimmer, *v. i. See* **Gleam.**

Shin, *s.* अग्रजंघा, पादः; *See* **Leg.**

Shine, *v. i.* प्रकाश् 1 A, प्र-,भा 2 P, वि-द्युत् 1 A, शुभ् 1 A, दीप् 4 A, राज् 1 U, भास् 1 A, स्फुर् 6 P, भ्राज्-भ्राश्-भ्लाश् 1 A, चकास् 2 P, प्र-,रुच् 1 A, ज्वल् 1 P, विलस् 1 P; 'stars. s. by their own light' स्वतःप्रकाशाः तारकाः. **-s.** प्रकाशः, द्युति *f.*, प्रभा, *See* **Light. -ing,** *a.* भास्वत्, द्युति-दीप्ति-मत्, भासुर, रुचिर, तेजस्विन्, कांतियुक्त, भ्राजमान, द्योतमान, &c. **-y,** *a.* भास्वत्; *See* above.

Shingle, *s.* शर्करा, शिलाखंडः. **2** फलकः-कं.

Ship, *s.* पोतः; यानं, प्रवहणं, (the sense being clear): बृहन्नौका-तरणि-णी *f.*; 's.-master' नौकाधिपतिः, पोताध्यक्षः. **-v. t.** (Off) पोतेन प्र-स्था c. or प्र-हि 5 P, पोतं आरुह् c., नौकायां प्रविश् c. **2** स्वस्थाने निविश् c. **-Shipwreck,** *s.* यान-पोत-भंगः, नौव्यसनं-भंगः-भेदः; (fig.) विध्वंसः, उच्छेदः, प्रणाशः; 'suffered a s.' यानभंगेन सागरे निमग्नः. **-v. t.** नावं-पोतं-भंज् 7 P or भञ्ज् c.; 'her hopes were s. ed' सर्वा आशा उन्मूलिताः, मूलाच्छिन्ना इव.

Shirk, *v.* सव्याजं-छलेन-परिहृ 1 P or त्यज् 1 P or हा 3 P; अप-व्यप-दिश् 6 P, छलं-छद्म-कृ 8 U; व्यप-सृप् 1 P, व्यपक्रम् 1 U, 4 P, पलाय् 1 A. **-er,** *s.* कार्यत्यागिन् *m.*

Shirt, *s.* युतकं. चोलः, अधोवसनं-वस्त्रं.

Shiver, *v. i.* कंप्-वेप्-1 A, सीत्कारं मुच् 6 P.; 's.-ing with cold,' शीतकंपिततनु, शीतार्तत्वात् कंपमान, with s. ing force' सतरलवेगं. **2** बहुखंडशः भिद्-विद्-pass., शकलीभू 1 P. **-v. t.** शकलीकृ 8 U, बहुखंडशः भिद् 7 P or विद् 9 P or c., सहस्रधा भंज् 7 P. **-s.** प्र-,कंपः, वेपथुः, सीत्कारः, देह-गात्र-कंपः. **2** शकलः-लं, खंडकः, सूक्ष्मलवः, दलं, छेदः, भिन्नं; 'went to a hundred s. s' शतखंडीभूतः शतधा भिन्नः.

Shoal, *s.* गाधस्थलं, सैकतं, पुलिनं. **2** संघः (मत्स्यादीनां), संघातः; 's. of fish' पोताधानं

Shock, *s.* आ-अभि-घातः, निर्घातः, सं-वि-क्षोभः, संघट्टः, आकस्मिकक्षोभः; 'Oh hard s. of fate' अहह दारुणो दैवनिर्घातः (U. 2). **2** भयावेशः, साध्वसाक्रमः. **3** राशिः, उत्करः, चयः. **-v. t.** उप-अभि-हन् 2 P, वज्रेण व्यथ् 4 P or तड् 10, अकस्मात् उ-द्विज् c. or त्रस् c.; 'I am s. ed to hear this from you' एतत्त्वन्मुखाच्छ्रुत्वा वज्राहित इवास्मि-प्रचकितोस्मि. **2** सं-वि-क्षुभ् c., संघट्ट् c. **-ed,** *a.* आकस्मिकसाध्वसोपहत. **-ing,** *a.* उद्वेगकर (री *f.*), साध्वसकारिन्, बीभत्स.

Shoe, *s.* उपानह् *f.*, पादुका, पादूः, पादत्रं; (for horses &c.) खुरत्रं-त्राणं. **-v. t.** पादुकया नह् 10 or प्र-हृ 1 P. **2** खुरत्रेण सनाथीकृ 8 U, खुरत्रं बंध् 9 P. 's.-black, -cleaner' पादुकामार्जः; 's.-maker' चर्मकारः, पादूकृत्; 's.-string' पादुकाबंधनी.

Shoot, *s.* पल्लवः-वं, किस(श)लयः-यं, प्रवालः; प्ररोहः, अंकुरः नवपल्लवः; उद्भिद् *m.*, उद्भिज्जं. **-v. i.** आग्नेयास्त्रं-शरं &c. मुच् 6 P or अस् 4 P. **2** (Forth) निर्गम् 1 P, अंकुरयति (D.), उद्भिद् pass., प्ररुह् 1 P, स्फुट् 6 P, सहसा प्रादुर्भू 1 P; 'the bud though long shot forth' चिरनिर्गतापि कलिका (S. 6); better ex. by (*s.*); 'the seed has not yet shot forth' अंकुरोद्भवो नास्ति, प्ररोहाभिमुखमपि न दृश्यते बीजं (after K. v. 60). **3** निः-सृ 1 P, प्रवृत् 1 A. **4** मर्माणि भिद् 7 P or व्यध् 4 P. **-v. t.** प्र-,मुच्-क्षिप् 6 P, प्रास्, विसृज् 6 P, पत् c., ईर् c. **2** आग्नेयास्त्रेण-गुलिकाक्षेपेण-शरेण &c. हन् 2 P or प्रहृ 1 P or क्षण् 8 P or क्षि 5 P, हत्वा निपत् c.; 'shot (at) them only' तौ शरव्यमकरोत् स नेतरान् (R. xi. 27); 'shot in the eye' (गुलिका-)विद्धनयनः. **3** उत्-वि-सृज्, निरस्,निः-सृ c. **-er,** *s.* भेत्तृ *m.*, वेधिन् *m.* **-ing,** *a.* उद्भिद्-ज्ज, प्ररोहिन्. **-s.** शरप्रक्षेपः, शरासनं, बाणमोक्षणं. **2** गुलिकाप्रक्षेपः. **3** तीक्ष्ण-तीव्र-वेदना; 'one skilled in s.' कृतहस्तः, कृतपुंखः, सुप्रयोगविशिखः. **-Shot,** *s.* क्षेपः, प्रहारः, ताडनं &c. **2** अस्त्रं, मुक्तं, आग्नेयास्त्रं, गुलिका. **3** शरपातः, शरायणं. **4** विषयः, गोचरः. **5** लक्ष्यभेदप्रवीणः, लक्ष्यवेधिन् *m.*

Shop, *s.* शाला, पण्य or विक्रय-शाला or गृहं; आपणः, विपणि *f.*; 'work-s.' उद्योगशाला; 's.-keeper' आपणिकः, पण्याजीवः, विपणिन् *m.*, क्रयविक्रयिकः.

Shore, *s.* कूलं, तीरं, तटं, वेला, रोधस् *n.*; 'brought on the s.' उत्कूलित.

Short, *a.* (Of time) अल्प, स्तोक, स्वल्प; 'of s. duration' अल्पकालीन-कालिक (की *f.*), अचिरस्थायिन्. **2** (In size &c.) ह्रस्व, खर्व, वामन, अतुंग, नीच, क्षुद्र, लघु; ह्रस्वपरिमाण, अल्प-क्षुद्र-प्रमाण; क्षुद्रतनु, अल्पमूर्ति, पृश्नि. **3** अविस्तीर्ण, लघु, संक्षिप्त. **4** अपूर्ण, अपर्याप्त, ऊन, न्यून. **5** असायत, अदीर्घ. **6** हीन, विकल, रहित. **7** (Vowel) ह्रस्व, लघु; 'in a s. time' अचिरेण, अचिरात्; 'for a s. time' कंचित्कालं,

अल्पकालं-मात्रं; 'in s.' किं बहुना, समासेन, संक्षेपतः, संक्षेपेण, समासतः; 's. of' विना, अंतरेण, मुक्त्वा, ऋते; 'I shall be satisfied with nothing s. of Rama's banishment' नान्येन तुष्येयमृते रामविवासनात्; 'cut s.' आक्षिप् 6 P; संहृ 1 P, संक्षिप्; 'come or fall s.' न्यूनीभू 1 P, क्षि-अप-चि pass.; *See* **Fail**; 'a s.-cut' अवक्रः-सरलः-मार्गः; 'stop s.' अकस्मात् स्था 1 P, मार्गमध्ये स्था; 's.-coming' दोषः, प्रमादः, स्खलितं, छिद्रं, वैकल्यं, न्यूनता, अतिपातः, अपराधः; 's.-hand' संक्षिप्तलिपि *f.*, 's.-lived' क्षणध्वंसिन्-स्थायिन्-जीविन्-भंगुर, अचिरस्थायिन्, अल्पायुस्; 's.-sighted' अदूरदर्शिन्, अदीर्घदर्शिन्, ह्रस्वदृष्टि; 's.-winded' श्वासकृच्छ्राभिभूत, दुःश्वासिन्. **-en,** *v. t.* संक्षिप् 6 P, ह्रस् c., न्यूनी-अल्पीकृ 8 U, संकुच् 1 P, संहृ. **2** खर्वी-वामनी-कृ. **-***v. i.* ह्रस्वीभू 1 P, ह्रस् 1 P. **2** लघुतां गम् 1 P. क्षि pass., न्यूनीभू, अल्पीभू. **-ly,** *adv.* अचिरात्, अचिरेण, शीघ्रं, सपदि, झटिति; *See* **Quickly.** **2** संक्षेपतः, संक्षेपेण, समासतः; अविस्तरेण, अविस्तरशः. **-ness,** *s.* ह्रस्वता, क्षुद्रता, लघुता, अल्पता, खर्वता; अविस्तरः, संक्षेपः, न्यूनता, अपर्याप्ति *f.*, &c.

Should, Ex. by pot. pass. part. 'I s. think so' अहं तावदेवं मन्ये, इति मम मतिः.

Shoulder, *s.* स्कंधः, अंसः, भुजशिरस् *n.* **-***v. t.* स्कंधे कृ 8 U or स्था c. (स्थापयति), स्कंधेन वह् 1 P. **2** स्कंधेन तड् 10 or प्रहृ 1 P.

Shout, *s.* रवः, कलकलः, उत्क्रोशः, निनादः, महाशब्दः-स्वनः-नादः, प्रणादः, घोषः-षणा, कोलाहलः, संहूति *f.*; (of victory) जयघोषः-ध्वनिः-शब्दः, हर्षनादः, सिंहनादः. **-***v. i.* आ-वि-उत्-क्रुश् 1 P, उच्चैः-स्वन्-नद् 1 P or क्रुश्, घुष् 6 P or कृ with (*s.*), उद्-घुष् 10, मुक्तकंठं रु 2 P.

Shove, *v. t.* प्र-सृ c., संचल् c.; *See* **Push;** 's. off' अपसृ c. **-***s.* प्रसारणं, अपसारणं.

Shovel, *s,* खनित्रं, अभ्रि *f.*, काष्ठकुद्दालः.

Show, *v. t.* दृश् c. (with acc. or dat. of person), प्र-सं-° **2** निर्दिश् 6 P, सूच् 10, प्रकाश् c., व्यंज् 7 P or c., व्यक्तीकृ 8 U; आविष्कृ, प्रकटीकृ; आ-उप-दिश् 6 P or c. (way). **3** कथ् 10, आ-,ख्या 2 P, बुध् c., ज्ञा c. (ज्ञापयति), आ-नि-विद् c.; 's. me the way' आदेशय मे मार्गं; 's. a favour' उपकृ, अनुग्रह् 9 P; 's. off' दंभार्थं दृश् c.; 's. to be true' प्रति-पद् c. **-***v. i.* **Appear,** q. v. **-***s.* दर्शनं, आलोकः, प्रेक्षास्थानं, कौतुकं. **2** दृश्यं, स्थानं. **3** आभासः; by अव-आ-भा 2 P or भास् 1 A. **4** व्यपदेशः, व्याजः; *See* **Pretext.** **5** आडंबरः, दंभः. **-er,** *s.* प्र-,दर्शकः. **-y,** *a.* दृष्टिहारिन्, सुभगालोक; अतिदर्शनीय, एकांतशोभन.

Shower, *s.* वृष्टि *f.*, वर्षः, आसारः; धारासंपातः, धारासारः; 's. of arrows' शरवृष्टिः, इषुवर्षः; 's. of tears' अश्रुधारा, बाष्पासारः-धारा; 's.-bath' धारागृहं, धारायंत्रगृहं. **-***v. t.* वृष् 1 P, (fig. also). **-y,** *a.* वृष्टिमत्, बहुधार, वर्षुक.

Shred, *s.* खंडः-डं, शकलः-लं; वस्त्र-पट-खंडः. **-***v. t.* खंडशः व्यवच्छिद् 7 P.

Shrew, *s.* वक्र-वाम-शीला, कर्कशा उग्र-कटुशीला, कैकेयी. **2** छुछुंदरी, गंधमुखी (s.-mouse). **-ish,** *a.* वक्र-वाम-कटु-शील, कर्कश, कर्कशस्वभाव.

Shrewd, *a.* चतुर, विदग्ध, विचक्षण, निपुण, सूक्ष्मधी-मति. **2** वैदग्ध्यप्रयुक्त, विदग्ध in comp. **-ly,** *adv.* चातुर्येण, विदग्धवत् **-ness,** *s.* वैदग्ध्यं, चातुर्यं, &c.,

Shriek, *v. i.* परुषं आक्रंद् 1 P, वि-उत्-आ-क्रुश् 1 P, उच्चैः रु 2 P, आरट् 1 P, कर्कशं क्रुश्. **-***s.* आ-,क्रंदितं, क्रंदनं, रावः, रवः, उत्क्रोशः, कर्कशनादः-रवः; *See* **Scream.**

Shrike, *s.* कलिंगः, पिंगः, धूम्या(म्रा)टः.

Shrill, *a.* कर्कश, परुष, तीव्र, पटु, कर्णकटु, कर्णवेधिन्. **-ness,** *s.* कार्कश्यं, कटुता.

Shrimp, *s.* इंचाकः, जलवृश्चिकः.

Shrine, *s.* पुण्यस्थानं, देवायतनं, तीर्थं.

Shrink, *v. i.* संकुच्-आकुंच्-संहृ-संक्षिप् pass., संकोचं इ-या 2 P, निमील् 1 P (lotus). **2** (Withdraw) सकंपं-सभयं-परावृत् 1 A, विन्नस् 1, 4 P, उद्विज् 6 A, भयेन-सहसा अपसृ 1 P or अपक्रम् 1 U, 4 P; (into) गात्रसंकोचेन प्रविश् 6 P. **-***v. t.* संकुच् 1 P, आकुंच् c., संहृ 1 P. **-ing,** *s.* संकोचः, आकुंचनं.

Shrivel, *v. i.* संकुच्-आकुंच्-विशॄ-pass. **-***v. t.* संकुच् 1 P, विशॄ 9 P or c.: better by 's.-ed.' **-led,** *a.* संकुचित, आकुंचित, विशीर्ण; (into wrinkles) वलिपूर्ण, वलिमत्, वलिन-भ.

Shroud, *s.* आच्छादनं, आवरणं. पिधानं. **2** शव-प्रेत-वस्त्रं-वसनं-आच्छादनं. **-***v. t.* आ-,छद् 10,; पि-धा 3 U, गुह् 1 U, गुप् 1 P; *See* **Cover, Conceal.**

Shrub, *s.* गुल्मः-ल्मं, विटपिन् *m.*, स्तंबः, क्षुपः, बालवृक्षः. **-by,** *a.* गुल्मावृत. **-Shrubbery,** *s.* गुल्मवाटिका.

Shrug, *v.* (असंतोषदर्शनार्थं स्कंधौ) धू 5, 9 U, संकुच् 1 P, संचल् c. **-***s.* स्कंधधूननसंकोचः.

Shudder, *v. i.* वेपृ-कंप् 1 A, प्र-वि-°, वि-प्र-स्फुर् 6 P. **-***s.*, **-ing,** *s.* प्र-,कंपः, वेपथुः, अंगकंपः-स्फुरणं-वेपनं. **-ing,** *a.* संजातवेपथु, सकंप.

Shuffle, *v. i.* नि-अप-ह्नु 2 A; अप-व्यप-दिश् 6 P, छद्म-छलं-कृ 8 U; *See* **Prevaricate.** 2 वंच् 10; *See* **Cheat.** –*v. t.* इतस्ततः संचल् c. or विक्षिप् 6 P. 2 संमिश्र् 10, बहुधा विकॄ 6 P, संकरीकृ 8 U, संकुलीकृ. –*s.*, **–ing,** *s.* वंचना, छलं, छद्मन् *n.*, अपव्यपदेशः, अप-नि-ह्नवः, जिह्मोक्ति *f.* 2 संचालनं, विक्षेपः, संमिश्रणं. **–er,** *s.* छद्म-कपट-वृत्तिः, छलिन् *m.*

Shun, *v. t.* परि-ह्रृ 1 P, वृज् 10, परि-वि-°, परि-,त्यज् 1 P, हा 3 P; न उपगम or उपसृ 1 P, संगमं परिहृ (a person).

Shut, *v. t.* अपि-पि-धा 3 U, सं-आ-वृ 5 U, नि-अव-रुध् 7 U, बंध 9 P, (book, hand &c.). (eye) नि-,मील् 1 P or c., मुकुलयति (D.). 2 संहृ 1 P, संकुच् 1 P, संवृ, संहन् 2 P, संपीड् 10. 3 रुध्, स्तंभ् 9 P or c., प्रतिबंध्. –*v. i.* नि-,मील् pass., मुकुलायते (D.). **–in,** निरुध्; बंध्, &c. **–out,** निवार् 10, नि-षिध 1, P, बहिष्कृ 8 U, निराकृ, व्यावृत् c. **–up,** सं-नि-रुध्, पि-धा. 2 मुखं स्तंभ्; 's. up in a box' संपुटीकृ, मंजूषायां निविश् c. **–ter,** *s.* कपा(वा)टः-टी-टं अवरोधकं, आच्छादनं.

Shuttle, *s.* नलिकः, सूत्रवेष्टः-ष्टनं, त(त्र)सरः

Shy, *a.* सलज्ज, शालीन, विनीत, सव्रीड. 2 कातर, भीरुस्वभाव; लोक-जन-भीत, भीरु, आलापविरक्त. –*v. i.* भी 3 P, 'the horse s. ed at a rock' पाषाणं दृष्ट्वाऽश्वः सहसा भीतः-चकितः. **–ness,** *s.* शालीनता, कातर्यं, भीरुता, भीति *f.*

Sibilant, *s.* ऊष्मन् *m.*, ऊष्मवर्णः.

Sibyl, *s.* सिद्धा, सिद्धस्त्री.

Sick, *a.* आतुर, पीडित, व्याधित, रुजार्त, रोगार्त, रुग्ण, रोगिन्, विकृत, अस्वस्थ, सामय, अभ्यांत, आमयाविन, अपटु, अभ्यमित. 2 (Mentally) संतप्त, पीडित, व्यथित, उपतप्त. 3 विवमिषु, वमनोन्मुख, वमनेच्छु. 4 निर्विण्ण, विरक्त, वितृष्ण, वीतस्पृह, द्वेषिन्; 's. of eating flesh' मांसाशने निर्विण्णः; 's. of the world' संसारविरक्त, उदीर्णवैराग्य; 'a man on a s.-bed' शय्यागतो रोगी, 'to be s.' वम् 1 P, छर्द् 10. **–en,** *v. t.* निर्वेद-वितृष्णां-विरक्तां-उत्पद् c. 2 वम् c. रोगितीकृ 8 U. –*v. i.* व्याधिना अभिभू pass., भू with (*a.*). 2 बध् desid. (बीभत्सते); *See* **Abhor.** **–ening,** *a.* बीभत्स, बीभत्साकर. **–ly,** *a.* रुग्ण, असुस्थ, अशक्त; गदोपसृष्ट; *See* (*a.*). 2 नित्य-सदा-रोगिन्, रोगशील; 's. by nature' जन्म-प्रकृति-रोगिन्. **–ness,** *s.* व्याधिः, रोगः, गदः, रुज् *f.*, अस्वास्थ्यं, आमयः, विकारः, उपतापः. 2 विवमिषा, वमनेच्छा, प्रच्छर्दिका, छर्दि-र्दी *f.*, वमः-मि *f.*

Sickle, *s.* दात्रं, लवित्रं, शस्यकर्तनी.

Side, *s.* पार्श्वः-र्श्वं, पक्ष, in all senses; कुक्षिः, पार्श्व-पक्ष-भागः; 'left s.' वामांगं, वामपार्श्वः; 'opposite s.' वि-प्रति-पक्षः; 'first s. (of arguments) पूर्वपक्षः; उत्तरपक्षः, &c.; 'at one's s.' पार्श्वतः, पार्श्वे; 'staying at the s.' पार्श्वगत-स्थित. 2 प्रांतः, सीमा, उपांतं, अंतः. 3 (Of a mountain) उत्संगः, कटकः-कं, नितंबः. 4 भागः; 'outer s.' बाह्यभागः; पूर्वभागः, &c. 5 (Direction) दिश्-शा; gen. ex. by त्र, तः affixed; 'on both s. s' उभयतः, उभयत्र; 'on the other s.' परतः, पारे; 'on the left s.' वामतः; 'on all s. s' सर्वत्र, सर्वतः, विश्वतः, समंतात्, समंततः, चतुर्दिक्षु; 's. by s.' पार्श्वापार्श्वि. 6 (Party, faction) पक्षः; 'one of the opposite s.' वि-प्रति-पक्षः; 'of the same s.' सपक्षः, स्वपक्षीयः, स्वपक्षावलंबिन् *m.*; 'relations on the fathers' s.' पितृपक्षाः बांधवाः. 7 (In geometry) भुजः, पार्श्वः, दोस् *m. n.*, बाहुः; (of a river) पारः-अवारः; 's.-long' वक्र, तिरश्चीन, अपांग-साचि-तिर्यक् in comp.; (*adv.*) पार्श्वतः, तिर्यक्, साचि, तिरः; 's.-long look' नयनोपांतविलोकितं. साचिवीक्षणं, अपांगदृष्टि *f.*, तिर्यग्दृष्टि, कटाक्षः; 's.-look' अपांगदर्शनं, कटाक्षः; &c. 's.-ways', 's.-wise' तिरश्चीनं, तिर्यक्, तिरः. –*a.* पार्श्व, पक्ष in comp : पार्श्वस्थ, पार्श्विक-पाक्षिक-(की *f.*); 's. breeze' पक्षवातः, पक्षद्वारं, &c., –*v. i.* 'to be on the s. of' पक्षे भू, पक्षं ग्रह् 9 U or आश्रि 1 U or आ-अव-लंब् 1 A: 'one who s. s' पक्ष्यः. **–er,** **sidesman,** *s.* पक्षपातिन् *m.*, पक्षीयः, भोद्ग्राहिन् *m.* *See* **Partizan.**

Sidereal, *a.* तारा, नक्षत्र in comp.

Sidle, *v. i.* तिर्यक् गम् 1 P or या 2 P. **–ing,** *s.* तिर्यग्गति *f.*

Siege, *s.* उप-,अव-,रोधः, परिवेष्टनं; 'lay s. to' उप-अव-रुध् 7 U.

Siesta, *s.* दिवानिद्रा.

Sieve, *s.* चालनी, तितउः.

Sift, *v. t.* पृथक् कृ 8 U. वि-,क्षुभ् c., तितउना क्षुभ् c., निर्गल् c. 2 सूक्ष्मं-निपुणं-निरूप् 10 or परीक्ष् 1 A or आलोच् 10 or अनुसंधा 3 U. **–ing,** *s.* शोधनं, निर्गालनं.

Sigh, *s.* नि(निः)श्वासः, उच्छ्वासः, उच्छ्वसितं, दीर्घश्वासः-निश्वासः &c. –*v. i.* दीर्घं नि-उत्-श्वस् 2 P. निश्वासं मुच् or सृज् 6 P; 's. ing deep and hot' दीर्घं उष्णं च निश्वस्य. 2 क्रुश् 1 P, रुद् 2 P. *See* **Lament.** **–ing,** *a.* निश्वासिन्, उच्छ्वासिन्, दीर्घनिश्वासिन्, सनिश्वास.

Sight, *s.* *See* under See

Sign, *s.* चिह्नं, लक्षणं, लिंगं, अभिज्ञानं, लांछनं, व्यंजनं-कं; 'a bad s.:' अव-दुर्-लक्षणं. 2 संज्ञा, संकेतः, इंगितं. 3 **Portent,** q. v. 4 राशिः. 5 चिह्नं (in Math.&c.); 's. manual' स्वहस्तः, स्वाक्षरं, स्वहस्ताक्षरं; 'under one's own s. manual' स्वहस्तपरिचिह्नित (Y. II. 93). 6 ध्वजः; 's.-post' ध्वजस्तंभः. **-v.**; 'make a sign' संज्ञां दा 3 U; 'understand the s.' संज्ञां ग्रह् 9 U; 'makes a s. to Vidushaka' विदूषकं संज्ञां लंभयति; 's. ed to him by her eyes to come' नेत्रसंज्ञया तं आह्वयत्; गुरुं नेत्रसहस्रेण नोदयामास वासवः (K. II. 29) 's. ed to speak &c.'. 2 नाम लिख् 6 P or निविश् c. (with loc.); स्वाक्षरेण अंक् 10 or चिह्नयति (D.). **-atory,** *s.* स्वनाम-लेखकः-निवेशकः. **-ature,** *s.* नामलेखनं-निवेशनं. 2 नामाक्षरं, हस्ताक्षरं. **-Signal,** *s.* संज्ञा, संकेतः. **-a.** अपूर्व, अनन्यसाधारण (णी *f.*), विशिष्ट, स्मरणार्ह, अत्युत्कृष्ट, विशेष in comp. **-ize,** *v. t.* प्रसिद्धी-विश्रुती-कृ 8 U; (oneself) कीर्ति-प्रतिष्ठां-यशः-आप् 5 P or लभ् 1 A. **-ly,** *adv.* अति, नितरां, अत्यंतं, अपूर्वतया. **-Signet,** *s.* मुद्रा; 's.-ring' मुद्रासनाथमंगुलीयं, अंगुलिमुद्रा. **-Signify,** *v. t.* सुच् c., गम् c., द्युत् c., अभि-धा 3 U; *See* **Indicate, Mean;** oft. ex. by अर्थः; 'what does it s.' अस्य कोर्थः, किमनेन गम्यते, &c.; 'it s. es much' गुर्वर्थमेतत्. 2 by गौरवं, महत्त्वं, भारः. 3 by शक्ति *f.*, बलं. **-icance,** *s.* गौरवं, महत्त्वं. **-icant,-icative,** *a.* सार्थ, चरितार्थ, अर्थयुक्त, समर्थ, अर्थान्वित, अर्थवत्, पूर्णार्थ. 2 हेतुगर्भ, साकूत, अभिप्रायगर्भ; 'casting at me a s. look' साकूतं मां निर्वर्ण्य. 3 वाचक, अभिधायक, दर्शक, सूचक. 4 गुरु, महत्. **-icantly,** *adv.* अर्थवत्, साकूतं, सार्थं, पूर्णार्थतः. **-ication,** *s.* अर्थः. 2 शक्तिः.

Signior, *s.* आर्यः.

Silent, *a.* तूष्णीक, अनालापिन्, मूक, मौनिन्, निःशब्द, नीरव. 2 कद्र्-बद्ध-मुख, निरुत्तर, अनुत्तर; 'habitually s.' तुष्णींशील, अल्पभाषिन्, वाग्यत, वाचंयम; 'when the lute was s.' वीणायां मूकीभूतायां; 'become or remain s.' (after speaking) उपशम् 4 P, विरम् 1 P; एवमुक्त्वा उपशशाम, उपशांतवचसि तस्मिन् &c. **-ly,** *adv.* तूष्णीं, जोषं, निःशब्दं, निभृतं, मौनीभूय. **-Silence,** *s.* मौनं, मूकभावः, निःशब्दता, अनालापः, तूष्णींभावः, अभाषणं; 'keeping s.' वाक्स्तंभः-रोधः-यमनं, मुखबंधनं; 'one who holds s.' वाचंयमः, मौनव्रतिन् *m*; 'keep s.' तूष्णीं-जोषं-आस् 2 A or स्था 1 P; मौनं आस्था-भज् 1 A, वाचं यम् 1 P or निरुध् 7 U, मुखं बंध् 9 P. 2 प्र-,शांति *f.*, स्तिमितता; 'in the s. of night' प्रशांतायां रात्रौ. **-interj.** तूष्णीं भव, मौनं कुरु. **-v. t.** मौनं लभ् c. (लंभयति) or अवलंब् c., विरम् c., प्र-उप-शम् c. 2 निरुत्तरीकृ 8 U, अधरीकृ, मुखं बंध्. **-ed,** *a.* निरुत्तर, अनुत्तर, निरुत्तरीकृत, कद्र्-बद्ध-मुख.

Silk, *s.* कौशेयं, कोशं, कीटसूत्रं; पट्टः, क्षौमं, दुकूलं, कौशांबरं, कौशिकं (s.-cloth); China s. चीनांशुकं; 'bleached s.' पत्रोर्णं, धौतकौशेयं; 's.-cotton tree' शाल्मलिः-लः, शाल्मलिवृक्षः, पिच्छिला; 's.-worm' कोश(ष)कारः, पट्टकीटः, तंतुकीटः-कृमिः, कोशस्थः. **-en,** *a.* कौशेय (यी *f.*), क्षौम (मी *f.*), कौशिक (की *f.*), कौश (शी *f.*); 's.-cloth' दुकूलं, कौशांबरं, क्षौमं, &c. 2 मृदु, कोमल.

Sill, *s.* देहली, शिला, गृहावग्रहणी.

Silly, *a.* मूर्ख, बालिश, मूढ, अल्पधी-मति, दुर्मति, निर्बुद्धि; *See* **Foolish;** 'what a s. boy' अहो मूढो बालकः.

Silt, *v. t.* (up) अवरुध् 7 U, अवबंध् 9 P.

Silvan, *a.* वन in comp., वन्य, वनस्थ, अरण्यज; 's. goddess' वनदेवता; 's. scenery' वनशोभा-श्रीः.

Silver, *s.* रूप्यं, रजतं, श्वेतं, दुर्वर्णं, खर्जूरं, कलधौतं; s. leaf रूप्यपत्रं 's.-smith' रूप्यकारः, स्वर्णकारः. **Silver wedding,** *s.* पंचविंशा विवाहतिथिः. **-a.** राजत (ती *f.*) (*s.*) in comp., रजतनिर्मित-कृत, रौप्य (प्यी *f.*). **-v. t.** आच्छद् 10, रजतयति (D.), श्वेतवर्णीकृ 8 U. **-y,** *a.* रजतोपम, रूप्यवर्ण, श्वेत-शुभ्र-वर्ण, अतिधवल.

Similar, *a.* सम, समान, तुल्य, अनुगुण, अनुरूप, सधर्मन्; *See* **Like.** **-ity,** *s.* साम्यं, सादृश्यं, तुल्यत्वं. **-ly,** *adv.* तद्वत्, तथैव, एवं.

Simile, *s.* उपमा, निदर्शनं. **-Similitude,** *s.* औपम्यं, सादृश्यं. 2 आकारः, रूपं, मूर्ति *f.*

Simmer, *v. i.* शनैः पच्-क्वथ् pass.

Simper, *v. i.* विकृतं स्मि 1 A, कुस्मितं कृ 8 U, अनर्थकं हस् 1 P.

Simple, *a.* निरवयव, असंकीर्ण, असमस्त, शुद्ध, केवल, अमिश्र. 2 सरल, ऋजु, अमाय, शुद्धात्मन्, अवक्र, निर्व्याज, निष्कपट, मायाहीन. 3 (Dress) विनीत, (विनीतवेषेण प्रवेष्टव्यानि तपोवनानि S. 1). 4 स्पष्ट, व्यक्त, सुगम, सुबोध, भिन्नार्थ, अगूढार्थ; *See* **Plain.** 5 मुग्ध, बालिश, मूढ, दुर्मति. **-s.** ओषधि-धी *f.* **-Simpleton,** *s.* मूढः, मूढधीः, सुविश्वास्यः, क्षुद्रः, क्षुद्रमतिः. **-Simplicity,** *s.* शुद्धता, अमिश्रता, सरलता,

आर्जवं, सारल्यं, निर्व्याजता, अनुपधित्वं, अमाया, अव्याजः, निष्कापट्यं. 2 विनीतत्वं, ऋजुता. 3 स्पष्टता, सुबोधता, सुगमत्वं. 4 बालिश्यं, मूढता. **-Simplify,** *v. t.* ऋजूकृ 8 U, विशदीकृ, सुगमीकृ, व्यक्तीकृ; *See* **Explain.** **-Simply,** *adv.* एव, केवलं, मात्र in comp.

Simulate, *v. t. See* **Pretend.**

Simultaneous, *a.* एक-सम-कालिक (की *f.*), यौगपद्यिक. **-ly,** *adv.* समं, युगपत्, एक-सम-कालं-ले, यौगपद्येन, एकदैव, सममेव. **-ness,** *s.* यौगपद्यं, एक-सम-कालता, युगपद्भावः.

Sin, *s.* पापं, पातकं, एनस् *n.*, कल्मषं, दुरितं, अघं, दुष्कृतं, वृजिनं, अंहस् *n.*, किल्बिषं, पंकः-कं, पाप्मन् *m.*, कलुषं; दोषः, अपराधः, पाप-अप-कर्म *n.*, कुकर्मन्, दुष्कृतिः *f.*-त्यं; 'heinous s.' महा-घोर-पातकं; 'destroying s.' पापनाशन-नाशिन्, अघमर्षण, पापापह. **-***v. i.* पापं &c. आचर् 1 P or कृ, अपराध् 4, 5 P, दुष् 4 P. **-ner,** *s. See* **Sinful** below; 'an atrocious s.' महा-घोर-पातकिन्-पापिन्, पापराशिः-निधिः. **-ful,** *a.* पापिन्, पातकिन्, पापकर (री *f.*), पाप्मन्, पाप-कृत्, पापात्मन्, कुकर्मन्, दुष्कर्मन्, एनस्विन्, पाप-दुष्ट-कर्मन्, अपराधिन्, किल्बिषिन्, पाप-निरत-बुद्धि-मति, पापात्मक. 2 (Of acts) पाप in comp., दुष्ट; कलुष; 's. act' पापं, दुष्कर्म; *See* (*s.*). **-fully,** *adv.* पापवत्, सपापं, दुष्टवत्. **-fulness,** *s.* सपापता, पापमति-निरति *f.*, दुष्टता, &c. **-less,** *a.* अनघ, निष्पाप, अपाप, अकल्मष, पापरहित, निर्दोष, निरपराध, and sim. comp.

Since, *prep.* प्रभृति, आरभ्य, (with abl.), आ with abl. or in comp.; sometimes also ex. by gen. abs.: अस्य कतिपये संवत्सरास्तपस्तप्यमानस्य (U. 4) 'it is several years s. he began to practise penance'; 's. then' तदाप्रभृति; '4 years s.' इतः पूर्वं चतुर्वर्षे; 'long s.' चिरं; 'ever s.' यतः प्रभृति. 2 पूर्वं, प्राक्, गत-पूर्व-काले. **-***conj.* यतः, यस्मात्, यत्, हि (not at beginning); by abl. of abstract noun; *See* **Because.**

Sincere, *a.* अकृत्रिम, निर्व्याज, निष्कपट, निर्व्यलीक, दक्षिण, ऋजु, सरल, विशुद्ध, अमाय; यथार्थ, सत्य, तात्त्विक-वास्तविक (की *f.*); (of persons only) शुद्धमति-भाव, शुद्धात्मन्, विमलात्मन्, शुचि, सत्यशील-व्रत-वादिन्; *See* **Frank, Honest.** **-ly,** *adv* निर्व्याजं, निर्व्यलीकं, अमायया, शुद्धहृदयेन-भावेन, विमलात्मना. **-ity, -ness,** *s.* सारल्यं, दाक्षिण्यं, आर्जवं, निष्कापट्यं, अमाया, विमलात्मता, शौचं, यथार्थता, &c.

Sine, *s.* ज्या, ज्यार्धिंडः.

Sinecure, *a.* अकर्माधिकृत, कर्मशून्याधिकारिन्.

Sinew, *s.* स्नायु *f.*, स्नसा; (*s.* 2) बलं, शक्ति *f.*, सामर्थ्यं. **-y,** *a.* स्नायुमय (यी *f.*). 2 प्र-स-बल.

Sing, *v. i.* गै 1 P; (of birds) कूज् 1 P, रु 2 P. **-***v. t.* गै, गानेन वर्ण् or कृत् 10, उत्कृत्, अभिगै; 'they sang his praises' तं स्तुतिभिरुपतस्थिरे. **-er, -Songster,** *s.* गायकः, गातृ *m.* **-ing, -Song,** *s.* गीतं, गीति *f.*, गेयं, गानं. 2 कूजनं. रुतं. रावः. रवः.

Singe, *v. t.* ईषद् दह् 1 P, अग्निना स्पृश् 6 P.

Single, *a.* एक, एकाकिन्, अद्वितीय, केवल, असहाय; अद्वैध (धी *f.*). 2 भिन्न. व्यक्त, अविभक्त. 3 **Simple,** q. v. 4 अनूढ, अविवाहित, अकृतोद्वाह, निःसंग; 's. combat' द्वंद्वयुद्धं, नियुद्धं, बाहुयुद्धं; 's.-handed' एक, एकाकिन्, बाहुसहाय, भुजमात्रसहाय; 's.-hearted' अनन्यवृत्ति, एकचित्त; 's. stick' यष्टि *f.*, दंडः. **-***v. t.* (Out) (बहूनां मध्यात्) वृ 5 U, उद्धृ 1 P, उद्-ग्रह् 9 P; निरूप् 10, निर्दिश् 6 P. **-ness,** *s.* कैवल्यं, अद्वितीयता, &c. 2 शुद्धि *f.*, अनन्यता, अनन्यभावः. **-Singly,** *adv.* Ex. by (*a.*). 2 एकैकं, एकैकशः, प्रत्येकं, एकशः, पृथक्, पृथक् पृथक्; *See* **Separately.**

Singular, *a.* अपूर्व, अप्रतिम, अद्वितीय, अप्रतिरूप, अनुपम. 2 अनन्यसाधारण (णी *f.*), लोकोत्तर, अनन्यसामान्य; अपरूप, विलक्षण, अद्भुत, लोकबाह्य, अलौकिक (की *f.*); 's. number' एकवचनं. **-ity,** *s.* अपूर्वता, अप्रतिमता, असामान्यता, वैलक्षण्यं, वैचित्र्यं, असंगति *f.*, लोकोत्तरता. **-ly,** *adv.* अपूर्वं, विशेषतः, अद्भुतं, लोकोत्तरप्रकारेण.

Sinister, *a.* अमंगल, अशुभ, अकल्याण (णी *f.*), अभद्र. 2 दुष्ट, वक्र, वाम, कुटिल, अनृजु. 3 वाम, सव्य; 'of s. motives' दुराशय, पापमति; उमां स पश्यन्नृजुनैव चक्षुषा (K. v. 32) 'looking at Umā with no s. eye'. **-Sinistrally,** *adv.* वामतः, वामदिशि. **-Sinistrous,** *a.* वामस्थ, वामपार्श्ववर्तिन्.

Sink, *v. i.* नि-मस्ज् 6 P; 'sank in deep mire' महापंके निमग्नः; सद् 1 P. अव-नि-°, अधः गम् 1 P or पत् 1 P or या 2 P, अव-पत्. 2 ह्रासं-क्षयं या-इ 2 P, क्षि pass., ध्वंस् 1 A; *See* **Decay, Decline.** 3 (Down) अव-वि-सद्, परि-, म्लै-ग्लै 1 P, स्रंस् 1 A; *See* **Droop;** 'my heart s. s down' सीदति मे हृदयं; 'limbs, s. ing down through excessive thirst' प्रबल-पिपासावसन्नानि अंगकानि (Ka. 36); 'his heart sank within him' तस्य धैर्यमही-

पत; स लुप्त-स्खलित-धैर्यः. -v. t. नि-मस्ज् c. (मज्जयति); अधः गम् c. or पत् c. 2 (A well &c.) खन् 1 P. 3 अवसद् c., परि-, म्लै c. (spirits &c.) 4 न्यूनीकृ 8 U. अल्पीकृ, लघयति ((D.), ह्रस् c., अपचि 5 U: क्षि 5 P. -s. जलनिर्गमः, सुसनाली.

Sinuous, *a.* कुटिल, वक्र, अराल, जिह्म. **-Sinuosity,** *s.* वक्रिमन् *m.*, कौटिल्यं.

Sinus, *s.* नाडि-डी-लि-ली *f.*

Sip, *v. t.* आचम् 1 P: उपस्पृश् 6 P. ईषत्-अल्पशः-पा 1 P. -s. आचमनं, उपस्पर्शः, ईषत्पानं.

Siphon, *s.* उत्क्षेपणी, वक्रनाली.

Sir, (Voc.) आर्य; भवन्, भोः; 'holy s.' भगवन्; 'gentle or good s.' भद्र, भद्रमुख.

Sirdar, *s.* मांडलिकः, सामंतः. 2 सेनानी *m.*

Sire, *s.* (In addressing) देव, श्रीमद्देव, महाराज, राजन्. 2 भगवन् (of holy men). 3 तातः, जनकः, पितृ *m.*

Siren, *s.* वि-,मोहिनी, (गानेन) लोभयित्री, मायिनी.

Sirrah, *interj.* रे, अरे, अरेरे.

Sirrup, *s.* स्वादु or मधुर-रसः or पेयं

Sister, *s.* स्वसृ *f.*, भगिनी, सोदर्या, जा(या)-मिः-मी. 2 धर्मभगिनी; 'elder s.' अग्रजा; 'younger s.' अवरजा; 's.'s son' भागिनेयः, स्वस्रेयः; 's.'s daughter' स्वस्रीया, भागिनेयी; 's.'s husband' आवुत्तः; 's.-in-law' यातृ, ननांदृ, श्याली. भ्रातृजाया, प्रजावती (expressing different relations). **-hood,** *s.* भगिनीत्वं, भगिनीसंबंधः. 2 भगिनीसमाजः, स्त्रीगणः. **-ly,** *a.* भगिन्यनुरूप, स्वस्रीय, स्वसृयोग्य.

Sit, *v. i.* आस् 2 A, नि-,सद् 1 P, उपविश् 6 P: 'please s. here' अत्रास्यतां, इदमासनमलंकरोतु भवान्. 2 कार्यं निर्वह् c. 3 (Fit) Ex. by शुभ् 1 A; 'this crown s. s well on you' नितरां तवेदं मुकुटं शोभते, शोभसे एतेन मुकुटेन; 's. by' उपास्, अन्वास्; 's. up' स्था 1 P, सम्यक् (अनतकायं) स्था; 'half s. ing up in the bed' पूर्वार्धविसृष्टतल्पः (R. xvi. 6); जागृ 2 P.

Site, *s.* सन्निवेशः, सं-,स्थिति *f.*, स्थानं, पदं, स्थलं, आस्पदं, भूमि *f.*; (of a house) वास्तु *m. n.*, वेश्मभूः, गृहपोटः; 'purificatory ceremony of a s.' वास्तुशमनं.

Situate,-ed, *a.* अव-,स्थित, निविष्ट; दिश्य, स्थ, वर्तिन् in comp.; 's. to the east' पूर्वदिश्य, पूर्वस्थ; (of persons) स्थ, स्थित, अवस्थ in comp.. अवस्थापन्न; 'so s.' एतदवस्थ; 'badly s.' दुःस्थ, दुःस्थित, कृच्छ्रगत, कष्टदशापन्न. **-ion,** *s.* सन्निवेशः, अवस्थानं, अव-,स्थितिः. 2 पदं, नियोगः, अधिकारः, पदवि-वी *f.* 3 अवस्था, दशा, स्थितिः, भावः, वृत्ति *f.*, आस्पदं.

Sitz-Bath, *s.* कटिस्नानं.

Six, *a.* षष्; 's.-fold' षड्गुण; 's.-faced' षण्मुखः, षडाननः; 'having s. mothers' षाण्मातुरः; 'collection of s.' षट्कं; 'in s. ways' षड्धा, षोढा; 'of s. months standing' षाण्मासिक (की *f.*), षण्मास्य. **-th,** *a.* षष्ठ (ष्ठी *f.*). **-Sixteen,** *a.* षोडशन्. **-th,** *a.* षोडश (शी *f.*). **-Sixty,** *a.* षष्टि *f.* **-ieth,** *a.* षष्टितम (मी *f.*).

Size, *s.* प्र-परि-माणं, मानं; 'of great s.' महाप्रमाण, पृथु; 'of a big s.' बृहत्प्रमाण. 2 आकारः, आकृति *f.*, रूपं, आकारमानं; 'of the s. of' ex. by (*s.*) or मात्र in comp.: 'of the s. of a mustard seed' सर्षपमात्र (छिद्रं); बिल्वमात्रं, अंडपरिमाणं, &c. 3 लेपः.

Skain, Skein, *s.* पं (पिं) जि-जी *f.*-जिका.

Skate, *s.* हिमविसर्पणपादुका.

Skeleton, *s.* कंकालः; 'mules reduced to s. s' कंकालशेषाः खराः (U.3); अस्थिपंजरः. 2 आकारः, संस्थानं. 3 वस्तुमात्रं.

Sketch, *v. t.* वर्ण् 10, आलिख् 6 P, स्थूल-वर्णनं-पांडुलेख्यं-कृ 8 U. -s. वर्णनं; आलेख्यं; 'rough s.' स्थूललेख्यं, पांडुलेखः; 's. of a painting' पांडुचित्रं, चित्रारंभः, रेखामात्रं. 2 वस्तुमात्रं.

Skew, *a.* तिर्यञ्च्, अनृजु, विषम. -*v. i.* तिर्यक् निरीक्ष् 1 A.

Skewer, *s.* शलाका, कीलः-लकः, शंकुः.

Skiff, *s.* तरीः, नौ *f.*, लघुनौका.

Skill, *s.* कौशलं, नैपुण्यं, पटुता, पाटवं, प्रावीण्यं, चातुर्यं, वैदग्ध्यं, युक्ति *f.*, विज्ञता, &c. **-ful, -ed,** *a.* कुशल, निपुण, प्रवीण, पटु, विचक्षण, दक्ष, विदग्ध, चतुर, विशारद, पेशल, युक्तिमत्, कृतिन्, विज्ञ, अभिज्ञ-ज्ञ-विद् in comp. **-ly,** *adv.* सपाटवं, सनैपुण्यं, दक्षतया, चतुरं, कुशलतया, विज्ञवत्, सवैदग्ध्यं, &c. **-ness,** *See* (*s.*) above.

Skim, *s.* मंडः-डं, फेनः-णः. -*v. t.* फेनं गल् c. or अपनी 1 P or निर्हृ 1 P. -*v. i.* जवेन-वेगात् परिसृप् 1 P or परि-द्रु 1 P, लघुगत्या विसृप्. **-med,** *a.* हृत-मंड-फेन; 's. milk' घोलं, मथिततक्रं. **-mer,** *s.* झर्झरी-रं, खजः-कः.

Skimp, *v. i.* कार्पण्यं समाचर् 1 P. 2 निरवधानं कृ 8 U.

Skin, *s.* चर्मन् *n.* (of animals), त्वच् *f.*; (hide) अजिन, दृतिः, कृत्ति *f.*, (of snakes) निर्मोकः, कंचुकः; 'reduced to mere s. and bones' त्वगस्थिमात्रशेष. 2 **Rind,** q. v.; 's.-deep' चर्मगत; *See* **Superficial;** 's-flint' अतिकृपणः, कदर्यः; *See* **Miser.** -*v. t.* चर्म-त्वचं-अपनी 1 P or निर्हृ 1 P or उत्क्षिप् 6 P. निस्त्वचीकृ 8 U.

-ny, *a.* चर्मभूत, त्वङ्मात्र, चर्ममात्रावशेष, क्षीण, कृश; *See* **Lean.**

Skip, *v. i.* प्लु 1 A, वल्ग् 1 P, नृत् 4 P. **-s., -ping,** *s.* प्लुत-ति *f.*, प्लवनं, प्लुतगति *f.* **-ping,** *a.* प्लुतगति-गामिन्.

Skipper, *s.* नौकाधिपः.

Skirmish, *s.* डिंबाहवः, डिंबः, डिंबयुद्धं. **-v.** *i.* कृ 8 U with (*s.*).

Skirt, *s.* प्रांतः, पर्यंतः, अंतः, प्रांत-पर्यंत-भागः, परिसरः, सीमा, धारा; 's. s of a mountain' पर्वतभूः. **2** अंचलः, दशा-वस्ति *m. f.* (pl.); वस्त्रांचलः, वसनांतः. **-v.** Ex. by (*s.*), प्रांतयति (D.); *See* **Border.**

Skittish, *a.* चंचल, चपल, तरल. **2** क्रीडा or खेला-शील or पर.

Skulk, *v. i.* निभृतं-अलक्षितं-स्था 1 P or वृत् 1 A, प्रच्छन्नं आस् 2 A.

Skull, *s.* कपालः-लं, कर्परः, शिरोस्थि *n.*; 's. for alms' भिक्षाकपालं; *See* **Scull.**

Sky, *s.* नभस् *n.*, वियत् *n.*, व्योमन् *n.*, गगनं-णं, आकाशः-शं, अंबरं, अंतरि(री)क्षं, खं, नाकः, दिव् *f.*, द्यो *f.*, विहायस् *m. n.*, विहायसः, अभ्रं, पुष्करं, अनंतं, सुरवर्त्मन् *n.*, विष्णुपदं, तारापथः; 'roaming through the s.' नभश्चरः, खेचरः, &c. 's.-coloured' व्योम-नील-वर्ण; 's.-lark' भ(भा)रद्वाजः; व्याघ्राटः; 's.-light' आकाशप्रकाशः; 's.-touching' अभ्रंलिह्-लिख्, नभोलिह्, व्योमस्पृश्, गगनचुंबिन्.

Slab, *s.* शिला, शिलातलं-पट्टः-फलकः.

Slabber, *v. i.* लालायते (D.), लालां स्रु c.

Slack, *a.* शिथिल, प्र-,श्लथ, स्रस्त, गलित. **2** मंद, अतीव्र, अतीक्ष्ण, प्रमत्त, अनवहित; *See* **Remiss. -en,** *v. t.* शिथिलयति (D.), श्लथ् 10, शिथिली-श्लथी-कृ 8 U, मंदीकृ; रथस्य मंदीकृतो वेगः (S. 1.) 'I have s.-ed the speed' &c.; प्र-शम् c. (शमयति) 'will not s. (the bonds of) her love' न अनुरागं शिथिलयति (V. 2.); 's. your pace a little' गतिवेगं किंचित् शिथिलय; 'who have s. ed their efforts' शिथिलितप्रयत्नाः, श्लथोद्यमाः. **-v.** *i.* शिथिली-श्लथी-भू, शिथिलायते (D.), मंदीभू; *See* **Relax. -ened,** *a.* शिथिलित, शांतवेगरय. **-ly,** *adv.* शिथिलं, प्रमादतः, अनवधानेन. **-ness,** *s.* शैथिल्यं, &c.

Slake, *v. t.* प्र-,शम् c. (शमयति), छिद् 7 P, (thirst). **2** जलेन संमिश्र् 10 or संसृज् 6 P. **-v.** *i.* प्र-,शम् 4 P.

Slam, *v. t.* (Door) तीव्राघातेन पि-धा 3 U or बंध् 9 P.

Slander, *s.* अप-परि-वादः, पैशुन्यं, पिशुनवचनं, अभि-,असूया, निर्वादः; *See* **Scandal. -v.** *t.* परि-अप-वद् 1 A, असूयति (with dat); अपभाष् 1 A, कलंकयति (D.), अभिशंस् 1 P: *See* **Defame, Libel. 2** सूच् 10, उपजप् 1 P, कर्णे जप्. **-er,** *s.* परि-अप-वादकः, अभि-,असूयकः, पिशुनः, सूचकः, कर्णेजपः, उपजापकः. **-ous,** *a.* पिशुन, साभ्यसूय, सपरिवाद, सापवाद, परिवाद-अपवाद-गर्भ, परिवादात्मक. **-ously,** *adv.* सापवादं, पिशुनं, सपरिवादं.

Slang, *s.* प्रलापः, अपभाषा, अश्लीलं-भाषणं, खलोक्ति *f.*

Slant,-ing, *a.* तिर्यच्, वक्र, कुटिल, तिरश्चीन; अवसर्पिन्, प्रवण; 'striking s.-ly with the tusks' तिर्यग्दंतप्रहारिन्; 's. blow' तिर्यक्प्रहारः. **-v.** *t.* आवृज् 10, वक्रीकृ 8 U, प्रवणीकृ **-v.** *i.* वक्रीभू, अवसृप् 1 P, प्रवणीभू, आनम् 1 P. **-ingly,** *adv.* तिर्यक्, तिरः, साचि, तिरश्चीनं.

Slap, *s.* चपेटिका, चपेटः, तल or चपेट-प्रहारः or आघातः, आस्फोटनं. **-v.** *t.* चपेटेन प्रहृ 1 P or तड् 10 or आहन् 2 U, आस्फुट् c.

Slash, *v. t.* दीर्घं छिद् 7 P or कृत् 6 P, व्यवच्छिद्, विनि-कृत्, क्षतविक्षतीकृ 8 U. **-s.** दीर्घ-महा-छेदः, महाक्षतं-ति *f.* **-ing,** *a.* दीर्घच्छेदकारिन्; (fig.) अरुंतुद, मर्मच्छिद्-भिद्, तीक्ष्ण; *See* **Sharp.**

Slattern, *s.* वेशप्रमत्ता, अपरिष्कृतवेशा.

Slaughter, *v. t.* विशस् 1 P, हन्, 2 P or c. (घातयति), व्या-पद् c., प्र-मी 9 U, आलभ् 1 A (beast); *See* **Kill. -s.** विशसनं, वैशसं, घातनं, प्रमाथः, कंदनं, संहारः, प्रमापणं; *See* **Killing;** 's.-house' सू(शू)ना, वध्यस्थानं वधभूमि *f.*, घातस्थानं. **-er,** *s.* घातकः, विशसितृ *m.*, सौ(शौ)निकः.

Slave, *s.* दासः, प्रेष्यः, चेटः, किंकरः, भृत्यः, दासेयः-रः, भुजिष्यः; *See* **Servant;** 'born a s.' गर्भदासः; 'domestic s.' गृहदासः; 'a female s.' दासी, चेटी, भुजिष्या; 's.-trade' दासविक्रयः; 's.-dealer' दासविक्रायिन् *m.*; (fig.) दासः, or ex. by वश, अधीन in comp.; 'a s. to carnal passions' इंद्रियसुखवशगः, विषयसुखाधीनः; 's. to love' कामपरवशः. **-ry,** *s.* दास्यं, दासत्वं, दासभावः, दास्यवृत्ति *f.* **-ish,** *a.* दासवत् *adv.*, दास in comp., दासोचित; *See* **Servile.**

Slaver, *s.* *See* **Saliva**

Slay, *v. t.* विशस् 1 P, हन् 2 P, व्या-पद् c., मृ c. **-er,** *s.* घातकः, हंतृ *m.*, हन् in comp.; *See* **Kill,-er.**

Sledge, *s.* अचक्रयानं.

Sledge-hammer, *s.* मुद्गरः, महाघनः.

Sleek, *a.* मृदु, श्लक्ष्ण, स्निग्ध, सुखस्पर्श.

Sleep, *v. i.* स्वप् 2 P, शी 2 A, संविश् 6 P, नि-द्रा 2 P, निद्रायते (D.); 'I also do not s. over this matter' मयाप्यस्मिन् वस्तुनि न शयानेन स्थीयते (Mu. 1.). *-s.* निद्रा, स्वप्नः, स्वापः, सुप्ति *f.*, शयनं, संवेशः; 'go to s.' निद्रां या 2 P; *See* (*v.*). 'fall into s.' निद्रया अभिभू pass. or आक्रम् pass.; 'he fell into a deep s.' गाढ-निद्राभिभूतः-विधेयः-बभूव; 'death-s.' घोर-काल-निद्रा; 'roused from s.' विनिद्र, भग्ननिद्र, प्रबोधित. **-er,** *s.* निद्रालुः, शयालुः, better by (*v.*). **-ing,** *s.* शयनं, निद्रा, &c.: 's.-house' शयनमंदिरं-गृहं. *-a.* निद्राण, शयित, शयान, सुप्त; 's. draught' निद्राकरमौषधं. **-less,** *a.* नष्टनिद्र, उन्निद्र, अ-वि-निद्र, निर्णिद्र; 'passes s. nights' उन्निद्राः-उत्सन्ननिद्राः-क्षपा गमयति. **-lessness,** *s.* निद्रानाशः, निर्णिद्रता, निद्राभावः. **-y,** *a.* निद्रालु, शयालु, तंद्रालु, निद्राशील. **2** निद्राक्रांत, निद्रापर-वश-विधेय-अभिभूत-आकुल-ग्रस्त. **3** निद्रामद-जनन (नी *f.*), स्वापकर (री *f.*). **4** सुषुप्सु, शिशयिषु, शयनेच्छु; 'to feel s.' स्वप्-शी-desid.: 'I feel s.' निद्रयाऽपन्हिये-पराभूये, सुषुप्सामि.

Sleet, *s.* शीकरः, तुषार or शीकर-वर्षः or आसारः.

Sleeve, *s.* पिप्पलः; 'to laugh in one's s.' अंतर् हस् 1 P.

Sleigh, *s.* *See* **Sledge.**

Sleight, *s.* (Of hand) हस्तलाघवं-कौशलं, माया, इंद्रजालं.

Slender, *a.* प्र-,तनु, कृश, क्षीण, क्षाम; 'having a s. waist', 's.-waisted' क्षीण or तनु-मध्य or मध्यम, कृशोदर, मृग or सिंह-कटि or मध्य; 's.-waisted woman' सुमध्यमा, कृशोदरी, तनुमध्या, वेदिविलग्नमध्या. **2** अल्प, क्षुद्र, लघु, तनु; 'possessed of s. means' क्षीणविभव. **-ness,** *s.* तनुता, कृशता, कार्श्यं, तानवं, अल्पता.

Sleuth, *s.* पदवी, पद्धति *f.*

Slice, *s.* खंडः-डं, शकलः-लं, छेदः, भागः, लवः. *-v. t.* खंड् 10, छिद् 7 P, खंडशः छिद्.

Slide, *v. i.* अव-वि-सृप् 1 P; 's. up and down' आरोहावरोहं कृ 8 U. **2** च्यु 1 A, स्खल् 1 P, भ्रंश् 1 A, 4 P. **-ing,** *s.* विसर्पः, अवसर्पणं, स्खलनं.

Slight, *a.* सु-,अल्प, स्तोक, क्षुद्र, तनु, लघु, ईषत् in comp.; 'a s. blow' लघुप्रहारः, ईषदाघातः; 'in a s. degree' ईषत्, किंचित्, मनाक्, स्तोकं, कियत्; 'not in the s. est degree' न मनागपि-किंचिदपि-स्तोकमपि. *-v. t.* उपेक्ष् 1 A, अवधीर् 10, अव-ज्ञा 9 U, तृणीकृ 8 U, तृणाय मन् 4 A, अवमन् 4 A, अवगण् 10; *See* **Contemn.** *-s.* उपेक्षा, अवधीरणं-णा, अवज्ञा, अवमानः, अनादरः, अवगणनं-ना. **-er,** *s.* उपेक्षकः, अनादरः. **-ing,** *a.* सावज्ञ, अनादरपूर्वक, सावमान. **-ingly,** *adv.* सोपेक्षं, अनादरेण. **-ly,** *adv.* ईषत्, मनाक्, किंचित्, स्तोकं, अल्पमात्रं, by आ pr.: 's. blue' आनील, ईषन्नील.

Slim, *a.* *See* **Slender.**

Slime, *s.* पंकः, श्यानकर्दमः, सांद्र-श्यान-पंकः. **-y,** *a.* श्यान, पंकिल, चिक्कण, सांद्र.

Sling, *s.* क्षेपणः, भिंदि(दि)पालः, गोफणा. **2** दोला, काचः, शिक्यं, भारयष्टि *f.* *-v. t.* क्षेपणेन क्षिप् 6 P or प्रास् 4 P. **2** उद्-बंध् 9 P, काचयति-आंदोलयति (D.).

Slink, *v. i.* अलक्षितं-निभृतं-अपया 2 P or अपगम् 1 P or अपसृप् 1 P or अपक्रम् 1 U, 4 P, छलेन अप-या, &c.

Slip, *v. i.* प्र-,स्खल् 1 P, (fig. also): वचनानि स्खलयन् पदे पदे (K. iv. 12) 'making their words slip.' &c.; चल् 1 P. **2** सहसा-अलक्षितं-अज्ञातः-निर्गम् 1 P or अपसृप् 1 P. **3** (Off) च्यु 1 A, प्र-,भ्रंश् 1 A, 4 P, स्रंस् 1 A, निर्-,गल् 1 P, पत् 1 P; 's. away' व्यप-या 2 P, अपसृप्-गम्; *See* **Slink;** 's. in' अलक्षितं आ-प्र-विश् 6 P; 'let s. an opportunity' अवसरं-समयं न ग्रह् 9 U or अवाक्षिप् 6 P. *-v. t.* अलक्षितं नि-धा 3 U or प्र-नि-विश् c. **2** वि-,मुच् 6 P, क्षिप्, भ्रंश् c.; अवगण् 10, उपेक्ष् 1 A, च्यु c., त्यज् 1 P, *See* **Neglect.** **3** शिथिलीकृ 8 U. स्रंस् c., शिथिलयति (D.); *See* **Loose.** *-s.* स्खलनं, स्खलितं, (fig. also); 's. as to names' गोत्रस्खलितं; प्र-,भ्रंशः, च्युति *f.*, पतनं. **2** दोषः, प्रमादः, अपराधः, भ्रमः, स्खलितं. **3** विटपः, शाखा, पल्लवः, कांडः. **4** खंडः-डं. **-pery,** *a.* पिच्छिल, मेदुर, चिक्कण, स्निग्ध, श्लक्ष्ण; 's. ground' निपत्या, पिच्छिलभूमिः. **2** अस्थिर, चल, लोल, तरल, अनवस्थित, चपल, चंचल; *See* **Fickle.**

Slipper, *s.* (लघु) पादुका, पादत्रं, उपानह् *f.*

Slit, *s.* दीर्घच्छेदः-वेधः-छिद्रं.

Slobber, *v. i.* लालां स्रु c.

Slop, *s.* (S. s) अधोंशुकं, अधोवसनं. **2** अमेध्यं-अपवित्रं-जलं, मलिनं-समलं-जलं. **3** कर्दमः, पंकः. *-v. t.* इतस्ततः प्रमादात् पत् c. or क्षिप् 6 P. **-py,** *a.* पंकिल, अनूप, सकर्दम.

Slope, *v. i.* अवसृप् 1 P, प्रवणीभू 1 P, क्रमशः निम्नीभू. *-v. t.* आनम् 10, प्रवणीकृ 8 U. *-s.* प्रावण्यं; प्रवणभूमिः, अवसर्पिणी भूमिः; क्रमशः निम्नता. **2** (Of a mountain) नितंबः, उत्संगः, कटकः-कं; 'mountain s.' गिरिनितंबः; अवसर्पिणी भूः. **-ing,** *a.* प्रवण, अवसर्पिन्, क्रमशः निम्न, पातुक.

Slot, *s.* छिद्रं. **2** कीलकः.

Sloth, *s.* तंद्रा, आलस्यं, तंद्रि-द्री *f.*, तंद्रिका, कार्यविमुखता. **-ful,** *a.* अलस, तंद्रिल, तंद्रालु; *See* **Lazy.**

Slouch, *v. i.* अलसं चल् or गम् 1 P. **-ing,** *a.* प्रलंब, निम्न

Slough, *s.* निर्मोकः, कंचुकः, अहि-भुजंग-त्वच् *f.* 2 महापंकः, पंकिलस्थानं, पंकाढ्य-स्थलं,

Sloven, *s.* अविनीत-अपरिष्कृत-वेशः. **-ly,** *a.* मलिन, अव्यवस्थित; अविनीत, अपरिष्कृत, अविनीत-अपरिष्कृत-वेश. **-liness,** *s.* अ-व्यवस्था, अपरिष्कारः, मालिन्यं.

Slow, *a.* मंद, (in all senses); मंदाग्निः, मंदगतिः, मंदमतिः, मंदवीर्य, &c.; मंदगति-गामिन्, अद्रुत; अक्षिप्र, अशीघ्र; मंथर; 'a mind s. to discriminate' मंथरविवेकं चेतः; 's. in recognizing' प्रत्यभिज्ञान-मंथर (S. 4.). 2 विलंबित; कालातीत अती-तसमय; *See* **Late.** 3 मंदमति-धी-बुद्धि, जड or स्थूल-बुद्धि or मति, &c.; *See* **Dull.** 4 दीर्घसूत्र-त्रिन्, चिरक्रिय; 's. time' विलं-बितवृत्ति *f.*; 's. fever' जीर्णज्वरः. **-ly,** *adv.* मंदं, मंदं मंदं, मंथरं; शनैः, शनैः शनैः, अशीघ्रं, अद्रुतं, विलंबेन. **-ness,** *s.* मांद्यं, मंदता; विलंबः, दीर्घसूत्रता, &c.

Sludge, *s.* पंकः.

Slug, *s.* प्रक्षेपणी गुलिका. 2 मंदः, अलसः, जडः, तुंदपरिमृजः, शीतकः, आलस्यशीलः, तंद्रालुः, स्थूल-जड-मतिः. **-gard,** *s.* *See* s. 2 above. **-gish,** *a.* मंद, अलस, तंद्रालु, मंदगति, आलस्यशील; *See* **Dull.** **-ly,** *adv.* मंदं, अलसवत्. **-ness,** *s.* मांद्यं, आलस्यं, तंद्रा, जाड्यं.

Sluice, *s.* (जल-) प्रवाहः, प्रपातः. 2 द्वारं, परि(री)वाहः, जलनिर्गमः.

Slumber, *v. i.* प्र-,स्वप् 2 P; अनिर्भरं स्वप्; (fig.) अनुपयुक्त-अव्यापृत-*a.* स्था or भू 1 P. **-s.** लघु-अल्प-अगाढ-निद्रा.

Slur, *s.* कलंकः, दूषणं, अकीर्तिचिह्नं. **-v. t.** 'cast a s. on' कलंकयति-मलिनयति- (D.), मलिनीकृ 8 U, दुष् c. (दूषयति). 2 प्र-,छद् 10, गुह् 1 U.

Slush, *s.* कर्दमः, सजलपंकः.

Slut, *s.* बंधकी, अविनीता, पुंश्चली; *See* **Prostitute.** **-tish,** *a.* अविनीत. अपरि-ष्कृतवेश.

Sly, *a.* धूर्त, कितव, कापटिक-छाद्मिक-(की *f*), समाय, सव्याज, वंचन-कपट-पटु. 2 चतुर, विदग्ध; 's. laugh' अंतर्हासः. **-ly,** *adv.* चातुरं, धूर्ततया, वैदग्ध्येन, सव्याजं, समायं. 2 निभृतं, अलक्षितं. **-ness,** *s.* व्याजः, छलं, छद्मन् *n.*, कापट्यं, माया, धूर्तता, वैदग्ध्यं, चातुर्यं.

Smack, *v. t.* Ex. by गंध, स्वाद in comp.; आ-अव-भास् 1 A; *See* **Savour.** **-v. t.** आ-,स्फुट् c.; आस्फल् c. 2 सशब्दं चुंब् 1 P. **-s.** आ-,स्वादः, रसः, गंधः. 2 आस्फोटनं, आस्फालनं; पक्षस्वनः. 3 सशब्दचुंबनं.

Small, *a.* अल्प, स्तोक, (of quantity). 2 लघु, तनु, अणु, क्षुद्र; अल्प-क्षुद्र-तनु, अल्प-शरीर, अणुक, अबृहत्, अमहत्; oft. ex. by क affixed; *See* **Little;** 's. tree' वृक्षकः; 's. boy' बालकः &c. 3 (Voice) नीच, अनुच्च; 's.-pox' मसूरी-रिका, विस्फोटकः; शीतला, वसंतरोगः (modern names).

Smart, *a.* तीक्ष्णमति, कुशाग्रबुद्धि, प्रदीप्तप्रज्ञ, चतुर; विदग्ध. 2 तीव्र, तीक्ष्ण, शीघ्र, द्रुत, लघु; आशु-शीघ्र-कारिन्. 3 (Speech &c.) सरस, मार्मिक (की *f.*), रसिक, रसगर्भ. 4 शोभन, सुवेश, प्रफुल्ल, सु pr. 5 (Pain &c.) तीव्र, तीक्ष्ण, उग्र, दुर्विषह; वेगवत्. **-s.** तीव्र-वेदना, तीक्ष्णव्यथा-वेदना; शूलः-लं. **-v. i.** व्यथ् 1 A, तप् pass., तीक्ष्णव्यथां अनुभू 1 P; 'I am s. ing under the defeat' पराभवो मम हृदि प्रत्युप्तं शल्यमिव; न्यक्कारो हृदि वज्रकील इव मे तीव्रं परिस्पंदते (Vi. 5.). **-ly,** *adv.* तीक्ष्णं, तीव्रं, शीघ्रं, द्रुतं; लाघवेन, शोभनं, सु pr. **-ness,** *s.* तीव्रता, तीक्ष्णता; शीघ्रमतित्वं, मार्मिकता, सरसता; शोभा, &c.

Smash, *v. t.* चूर्ण् 10, वि-,मृद् 9 P, निष्पि-ष् 7 P, भंज् 7 P, प्रमथ् 9 P, निर्दल् c. (दलयति); *See* **Break.** **-s.** प्रमाथः, नि-र्दलनं, विमर्दः, चूर्णनं, निष्पेषः-षणं.

Smatter, *v. i.* अल्पं ज्ञा 9 U, पल्लवग्राहि पांडित्यं कृ 8 U, किंचित् अवगम् 1 P. **-er,** *s.* चुंबकः, पल्लवग्राहिपंडितः; अल्पज्ञः. **-ing,** *s.* अल्पज्ञानं, पल्लवग्राहि पांडित्यं; oft. ex. by किंचित्, अल्पमात्रं; 's. of knowledge' अल्पत्वं ज्ञानं.

Smear, *v. t.* लिप् 6 P, वि-प्र-आ-अव-°, अभि-, अंज् 7 P or c., दिह् 2 U. **-ing,** *s.* लेपः-पनं, अंजनं.

Smell, *s.* घ्राणं; 'sense of s.' घ्राणेंद्रियं, घ्राणशक्ति *f.*, गंधग्रहणशक्तिः. 2 आ-,घ्राणं, गंधग्रहणं. 3 गंधः, वासः, आमोदः; *See* **Odour, Fragrance.** **-v. t.** घ्रा 1 P, आ-उपा-° **-v. i.** Ex. by गंध in comp. or सगंध-तुल्यगंध-*a.*; 's. ing of honey' मधुगंधि; 's. ing like fat' वसागंधि; 'the flower s. s sweet' मधुरोस्य कुसुमस्य गंधः; 'it s. s of smoke' धूमसगंधमेतत्. **-ing,** *a.* गंधग्राहिन्. 2 गंधयुत, सगंध, वासयुक्त.

Smelt, *v. t.* वि-ली c., वि-द्रु c. **-er,** *s.* लोहद्रावकः; लोहकारः.

Smile, *v. i.* स्मि 1 A, मंदं विहस् 1 P, ईषद् हस्, मंदस्मितं-मंदहास्यं-कृ 8 U; 's. on' अनुग्रह् 9 P; प्र-सद् 1 P, प्रसन्न-कृपार्द्रदृष्टि-*a.* भू (with loc.); 'fortune s. s on you' [illegible]

—*s.* स्मितं, मंदहासः-हास्यं-स्मितं, विहसितं, विहसनं; 'speaking with a s.' स्मितपूर्वाभिभाषिन्; 'with a s.' सस्मितं. -ing, *a.* स्मेर, सस्मित, स्मयमान, प्रसन्न, प्रफुल्ल; 's. sweetly' शुचिस्मित, चारुहासिन्; 'a s. countenance' स्मेर-हास्य-मुखं, प्रसन्न-प्रफुल्ल-वदनं. -ingly, *adv.* सस्मितं, विहस्य.

Smirch, *v. t.* मलिनीकृ 8 U

Smirk, *s.* विकृतहासः, विलक्षस्मित. —*v. i.* कृ 8 U with (*s.*)

Smite, *v. t.* हन् 2 P, प्र-हृ 1 P, तड् 10, नि-अप-कृ 8 U, तुद् 6 P; व्यध् 4 P; 's. en with anxiety' संस्पृष्टमुत्कंठया (S. 4); 's. en by love' मदनबाणहत, कामोपहत, कामार्त, मदनसंतप्त, अनंगपीडित. 2 हन्, मृ c., सूद् 10; *See* Kill. -er, *s.* हंतृ *m.* सूदनः, घातकः.

Smith, *s.* शिल्पिन् *m.*, कारः in comp.; 'iron s.' लोहकारः, अयस्कारः; स्वर्णकारः, &c. -ery,-y. *s.* शिल्प-कर्म-शाला; लोहकारशाला.

Smock, *s.* (स्थूल) शाटकः, अधोवसनं.

Smoke, *s.* धूमः-मिका, धूपः-पिका; 'a quantity of s.' धूम्या; 'cloud of s.' धूमपटलं-ओघः. —*v. t.* (धूमनालीं) पा 1 P, सेव् 1 A. 2 धूमेन क्षुध् c. or क्षुभ् c., धूप् 1 P, 10, धूपयति-धूमयति (D.). —*v. i.* धूमायते (D.), धूमं उत्क्षिप् 6 P or उद्-गॄ 6 P or निः-सृ c. or उत्सृज् 6 P; 's. ing food' धूमं विसृजत् (मोष्णं) अन्नं. 2 धूमनालीं पा. -er, *s.* धूमपः, धूमपायिन्-सेविन् *m.* -ing, *s.* धूमपानं. 2 धूमोत्क्षेपः-पणं. -less, *a.* निर्धूम, धूमहीन-रहित. -y, *a.* सधूम, धूमावरुद्ध, धूमबहुल. 2 धूम्र, धूमाभ, धूमल, धूमाकार. 3 धूमगंध-स्वाद.

Smooth, *a.* सम; श्लक्ष्ण, मृदु (fig. also); स्निग्ध, मसृण, अरूक्ष; अपरुष, अकटु, अकर्कश (sound); 'by s. words' श्लक्ष्णया गिरा, सांत्ववादेन, मृदुभिर्वचोभिः; 'by s. remedies' सामोपायैः. 2 धारावाहिन्, विसारिन्, सततप्रवाहिन्; निरुपद्रव, निर्विघ्न, निरंतराय, निर्बाध, (business &c.); शांत, अक्षुब्ध, प्रसन्न, अक्षुततरंग, निर्वात (water). —*v. t.* समीकृ 8 U, श्लक्ष्णीकृ. 2 अविघ्न-*a.* &c. कृ, निर्विघ्नीकृ. -ly, *adv.* सुखेन, निर्विघ्नं, निरंतरायं, अनायासेन. -ness, *s.* श्लक्ष्णता, स्निग्धता, मृदुता, अक्षोभः, प्रसादः, &c.

Smother, *v. t.* श्वासं अव-नि-रुध् 7 U, श्वासावरोधं कृ 8 U. 2 प्रति-,स्तंभ 9 P, निग्रह् 9 P, नियंत्र् 10, नियम् 1 P. -ed, *a.* रुद्धश्वास-प्राण.

Smoulder, *v. i.* अंतः ज्वल् 1 P or स्फुर् 6 P or दह् pass., better by 's. ing';

'just as a s.-ing tree bursts into flame' अंतःप्रसुप्तदहनो ज्वलतीव वनस्पतिः (U. 4). -ing, *a.* अंतर्दाहिन्-ज्वालिन्, गूढदाहवत्, प्रसुप्तदहन.

Smudge, *v. t.* मलिनयति (D); कृष्णी-अस्पष्टी-कृ 8 U, दिह् 2 U; —*s.* मलं, कलुषं, कलंकः.

Smug, *a.* शोभन, सुवेश.

Smuggle, *v. i.* प्रतिषिद्धानि भांडानि आह् 1 P or आनी 1 P.

Smut, *s.* मसी, मलं. 2 अश्लीलवाच् *f.*, दुरुक्तं, दुर्वचनं. —*v. t.*, **Smutch,** *v. t.* मलिनीकृ 8 U, मलीमसीकृ, मलिनयति (D.). -ty, *a.* मलिन, मलीमस. 2 अश्लील, दुरुक्त, अवाच्य.

Snack, *s.* *See* **Share, Repast.**

Snaffle, *s.* लघुवल्गा.

Snail, *s.* शंबूकः, कोष-कवच-स्थः. 2 मंथरः.

Snake, *s.* सर्पः, भुजगः, भुजंगः-गमः, पन्नगः, अहिः, नागः, उरगः, उरंगमः, विषधरः, भोगिन् *m.*, व्यालः, आशीविषः, फणिन् *m.*, दर्वीकरः, जिह्मगः, पवनाशनः, कुंभीनसः, दंदशूकः, चक्रिन् *m.*, द्विजिह्वः, द्विरसनः, सरीसृपः, कुंडलिन् *m.*, गूढपाद् *m.*, चक्षुःश्रवस् *m.*, काकोदरः, दीर्घपृष्ठः, बिलेशयः; 'hooded s.' फणभृत् *m.* भोगधरः, भोगिन् *m.*; 's. without poison' राजि(जी)लः, डुंडुभः; 's. with a spotted skin' मालुधानः, मातुलाहिः; चित्रसर्पः; 'that has cast off his slough' निर्मुक्तः, मुक्तकंचुकः; 'his venom' क्ष्वेडः, गरलं, विषं; 'his hood' स्फटा, फटा, फणा, स्फोटा दर्वी; 'charmer of s. s' अ(आ)हितुंडिकः, व्यालग्राहिन् *m.* -y, *a.* (*s.*) in comp.; आहेय (यी *f.*).

Snap, *v. t.* (अकस्मात्) त्रुट् c., भंज् 7 P, खंड् 10, छिद् 7 P. 2 आ-,स्फल् c., सहसा ग्रह् 9 U or उद्-हृ 1 P. 3 अकस्मात् दंश् 1 P; 's. the fingers' अंगुली स्फुट् c., छोटिकां दा 3 U or कृ 8 U. —*v. i.* (सहसा) त्रुट् 4, 6 P, दल् 1 P स्फुट् 6 P. भंज्-भिद्-pass. 2 क्वण् 1 P. 3 भष् 1 P 4 दंश् 1 P. दंतैः ग्रह् 9 U. —*s.*, -ping, *s.* त्रोटनं, आस्फालनं, आस्फोटनं, आकस्मिकभंगः. 2 छोटिका, मुकु(चु)टी, अंगुलिभंगः. 3 आकस्मिकदंशः. -pish, *a.* दंशनशील, द्विदंशु. 2 कर्कश, परुष, दुःशील, कुक्कुरस्वभाव.

Snare, *s.* पाशः, वागुरा, जालं; 'take in a s'. जाले बंध् 9 P; (fig.) उन्मार्गेण-अपथेन-प्रवृत् c. or गम् c. (गमयति) —*v. t.* पाशे पत् c., पातयित्वा बंध् 9 P. पाशीकृ 8 U; जाले बंध्.

Snarl, *v. i.* भष् 1 P, रै 1 P; गर्ज् 1 P. 2 परुष-कर्कशं-वद् 1 P. -er, *s.* भषकः, कर्कशः, भषशीलः-स्वभावः.

Snatch, *v. t.* (away) आच्छिद् 7 P, (कृपाणगतविषयात आछिंदतः प्रेयसीं Mal.

5); आक्षिप्य ग्रह् 9 U, झटिति ग्रह् or हृ 1 P or हृ 1 P or धृ 1 P, 10 or आ-कल् 10 (कलयति). -at, ग्रहीतुं यत् 1 A, सवेगं ग्रह् desid. (जिघृक्षति). -off, अपहृ, लुप् 9 P, चुर् 10. -out, उत्-कृष्, निर्हृ, उद्धृ, उन्मूल् 10, वि-उत्-पट् 10. -up, उत्क्षिप् 6 P, (उत्क्षिप्यैनां ज्योतिरेकं जगाम S. 5.). -s., -ing, s. आकस्मिकग्रहणं-धरणं; आच्छेदः, सहसा आकलनं. 2 अल्पांतरं, अल्पावकाशः. 3 क्षण-आकस्मिक-प्रवृत्ति f.; ' by s. es ' खंडशः; s. es of moonlight ' कदाचित्कः चंद्रप्रकाशः. -ing, a. लोलुप, गृध्नु; See Greedy.

Sneak, *v. i. See* **Slink.** -ing, *a.* कुत्सितवृत्ति, अधम, कापुरुषवृत्ति; *See* **Mean.**

Sneer, *v. i.* (at) अव-उप-हस् 1 P (with acc.). सहासं अवज्ञां सूच् 10; अव-ज्ञा 9 U, अवमन् 4 A; *See* **Deride.** -s. अव-उपहासः; अवज्ञाहासः. -ingly, *adv.* सोपहासं, सावज्ञं.

Sneeze, *v. i.* क्षु 2 P. कृ 8 U with (s.) -s., -ing, s. क्षुतं. क्षवः क्षवथुः, क्षुत् f., छिंजिः, छिक्का.

Snicker, Snigger, *v. i.* अंतर् हस् 1 P

Sniff, *v. t.* नासाघ्राणेन जि , घ्रा 2 P.

Snip, *v. t.* अग्रभागं-अग्रं-लू 9 U; *See* **Nip.**

Snipe, *s.* दीर्घचंचुः. 2 Fool, q. v.

Snivel, *s.* नासामलं, सिंहाण(घा)णं-नं. -*v. i.* मलं स्रु c.; ' he s. s ' तस्य नसः मलं स्रवति.

Snob, *s.* सभ्यंमन्यः, भद्रमानिन् *m.*

Snooze, *See* **Nap.**

Snore, *v. t.* घर्घरायते (D.), घर्घररवं कृ 8 U. -ings. *s.* घर्घरः, घर्घररवः, क्रथनं.

Snort, *s.* फू(फु)त्कारः. -*v. i.* फूत्कृ 8 U. फुत्कारं मुच् 6 P.

Snot, *See* **Snivel.**

Snout, *s.* प्रोथः, नासा, पोत्रं.

Snow, *s.* हिमं, तुषारः, तुहिनं, प्रालेयं, अवश्यायः, नीहारः, मिहिका; ' flo of s. ' तुषारस्रुति *f.*, हिमनिष्यंदः; ' s.-drift, ' ' mass of s. ' हिमानी, हिमसंहति *f.*, हिमराशिः; ' s.-capped ' हिमावृतशिखर; ' s-storm ' हिमवर्षः-संपातः. -*v. i.* हिमं वृष् 1 P, हिमकणान् मुच् 6 P. -y, *a.* हिमवत्, हैम(मी *f.*); तुषार-हिम-मय (यी *f.*), हिमावृत, (*s.*) in comp.; ' s. mountain ' हिमाद्रिः, तुहिनाचलः, &c. 2 हिमाभ, हिमवर्ण.

Snub, *v. t.* पराभू 1 P, अधिक्षिप् 6 P; प्रत्यादिश् 6 P, अधरीकृ 8 U, अपकृष् 1 P, वाचं रुध् 7 U; ' s. nose ' चिपिटनासा, नतनासिका; 's.-nosed' अवटीट, अवनाट, अवभ्रट, नतनासिक, चिपिट.

Snuff, *s.* नस्यं, नासाचूर्णं, क्षुत्करी; ' s.-box ' नस्यधानी, नस्याधारः. 2 दग्धवर्ति *f.*-तूला, छन्नं. -*v. t.* निश्वस् 2 P, अंतर् ग्रह् 9 U. 2 दग्धवर्तिं अवच्छिद् 7 P, छन्नं अपनी 1 P; ' s. out ' निर्वा *See* **Extinguish.** -ers, *s.* वर्तिकर्तनी-छेदनी. -y, *a.* नस्यदूषित-मलिन.

Snuffle, *See* **Snort.**

Snug, *a.* सु-,संहत, सु-,प्रच्छन्न, सुगुप्त, आवृत, सुगूढ, सुसंश्लिष्ट, सुरक्षित. 2 सुखावह, हितकर (री *f.*), सुस्थ, सुस्थित, सुख, स्वस्थ. 3 निकटशायिन्. -ly, *adv.* सुखेन, यथासुखं, सुसंहतं, सुसंश्लिष्टं, सुगुप्तं. -Snuggle, *v. i.* निकटेपार्श्वतः-शी 2 A.

So, *adv.* तथा, एवं, तद्वत्, एवंविधं; इति, इत्थं. 2 ईदृक्, एतावत्, इयत्, तथा, एतादृशं. 3 तत्, तेन, तस्मात्, ततः ' as-s. ' यथा-तथा; ' s.-that ' तथा-यथा; ' s. and so ' अमुक (की *f.*); मया अमुकसुतेन लिखितं अमुकेन (Y. II. 88) ' written by me s. and s., the son of s. and s. '; ' s.-called ' नाम, नामन् in comp.; ' s. far ' एतावत्, एतदवधि; एतावत्पर्यंतं; ' s. far as' तावत्, oft. ex. by इति; *See* **As;** ' s. forth ' इत्यादि, एवमादि; ' s. long ' एतावत्कालं यावत्, इयतो दिवसान्, इयंतं कालं; ' s. long as ' यावत्-तावत्; ' s. many ' इयत्, एतावत्; ' as many ' ' s. many ' यावत्-तावत्; ' s. much ' (*adv.*) तादृक्, ईदृक्, तथा; (*a.*) एतावत् इयत्; ' s. that ' येन, यथा; ' s. then ' एवं तर्हि, एतावता, एवं च; ' s. much as ' अपि, अपि तावत्; ' could not s. much as wet the tip of his bill ' चंचग्रमपि तावत् जलक्लिन्नं कर्तुं नाशकत्.

Soak, *v. t.* (चिरं) मस्ज् c. (मज्जयति), जलेन सिच् 6 P, क्लिद् c., आ-प्लु c., अभ्युक्ष् 1 P. -ed, *a.* जल-सिक्त-क्लिन्न, अभ्युक्षित.

Soap, *s.* मार्जनलेपः; perhaps अरिष्टः. फेनिलः (s. berry plant). -y, *a.* चिक्कण, स्निग्ध.

Soar, *v. t.* उत्पत्-उद्भ्रम् 1 P, उड्डी 1 A, ऊर्ध्वं विसृप् 1 P or डी; ' the aspirations of the great s. high ' उत्सर्पिणी महतां प्रार्थना (S. 7); ' high-s. ing hope ' दूराधिरोहिणी आशा (S. 5) -er, *s.* उड्डयनकृत् *m.* -ing, *s.* ऊर्ध्वगमनं, उड्डयनं, ऊर्ध्वारोहणं, दूराधिरोहणं.

Sob, *v. i.* सगद्गदं रुद् 2 P or क्रन्द् 1 P, फू (फू)त्कृ 8 U. -bing, *s.* फु(फू)त्कारः, गद्गदः, सगद्गदाक्रंदनं. -bingly, *adv.* सगद्गदं, गद्गदगिरा.

Sober, *a.* शांत, धीर, गंभीर, स्थिर, स्थिरमतिबुद्धि, विचारशील. 2 अमत्त, अक्षीव, निर्मद. 3 (In drinking) पानाप्रसक्त, पानसंय-

मिन्, अनतिपायिन्. 4 मित, परिमित, नियत, समर्याद. –*v. t* निर्मदीकृ 8 U, स्थिरीकृ, मदं अपनी 1 P, स्थैर्यं आ-पद् c. **–ed,** *a.* विगतमद, निर्मद, नष्टमद. **–ly,** *adv.* धीरवत्, गंभीरं, शांतचेतसा, विचारपूर्वं, सविवेकं. **–ness, Sobriety,** *s.* धीरता, गांभीर्यं, स्थैर्यं, विचारशीलता, सुविचारः; शांति *f.*, अनुद्वेगः, अरभसः. 2 अमत्तता, मदाभावः. 3 संयमः, निग्रहः, पानामसक्ति *f.*, मितपानं.

Sobriquet, *s.* उपाधिः, उपनामन् *n.*

Sociable, *a.* संगमप्रिय, संसर्गप्रिय-शील, जनसंगशील, संवासप्रिय-शील. 2 सुजन, मधुरालाप, सुशील, संलापप्रिय, स्नेहबुद्धि. **–ness, Sociability,** *s.* संसर्गशीलता, जनसंगमप्रीति *f.*; सौजन्यं, सुशीलं, संलापप्रियताशीलता

Society, *s.* संगमः, संगः, संसर्गः, समागमः, सहवासः, संगति *f.*, संवासः, साहचर्यं. 2 श्रेणी, संघः. 3 समाजः, लोक or जन-समूहः or संघः, पंक्ति *f.*, सभा-संसद्-परिषद् *f.*; admissible into s ' पांक्तेय, पांक्तेय, सभ्य. **–Social,** *a.* सामाजिक, सांसर्गिक (की *f.*); oft. ex. by (*s.*) in comp.; 's. interest' समाजहितं; 's. intercourse ' अन्योन्यसंघट्टनं, परस्परसंसर्गः-व्यवहारः. 2 **Sociable,** q. v. 3 संसर्ग or संगम-रूप or आत्मक.

Sociology, *s* समाजशास्त्रं.

Sock, *s.* पादत्रं, (और्ण) पादत्राणं.

Socket, *s.* आधारः, पात्रं, भाजनं.

Sod, *s.* शाद्वलं, तृणावृतभूभागः.

Sodality, *s.* मंडलं, संघः. 2 धर्मपथः

Sodden. *a.* अति-सिक्त-क्लिन्न; शून.

Sodomy, *s.* पुंमैथुनं, पुरुषमेहः, पायु-गुद-मैथुनं. **–Sodomite,** *s.* पुरुषमेहिन् *m.*, गुदमैथुनकृत्

Sofa, *s.* पर्यंकः, मंचः, शय्या; शयनं, आसनं.

Soft, *a.* मृदु (in all senses); प्रकृत्या मृदुः, मृदुगीः, मृदु पुष्पं, मृदुरुपायः. &c.; ' even red-hot iron becomes s. ' अभितप्तमयोऽपि मार्दवं भजते (R. viii. 43); ' neither very severe nor very s. ' न खरो न च भूयसा मृदुः (R. viii. 9); कोमल, मृदुल, पेलव, सुकुमार, अप्रखर, अपरुष, अकठोर, अनुग्र, अकठिन, अकर्कश, सौम्य (disposition). 2 स्निग्ध, श्लक्ष्ण, मसृण, मृदु-सुख-स्पर्श; आशिथिल, अदृढ, अघन; (voice) मधुर, मृदु, मंजुल; (in mind) सुमतार्थ, अल्पबुद्धि, बालिश. –*interj.* तूष्णीं भव, तूष्णीं, शांतं, नीचैः. **–en,** *v. t.* मृदूकृ 8 U, कृ with (*a.*) (with pity) दयार्द्रीकृ, वि-,द्रु c., करुणया द्रु c. 2 शम् c. (शमयति), प्र-,उप-°, सांत्व् 10, लघूकृ, लघयति (D.); *See* **Alleviate.** –*v. i.* मार्दवं भज् 1 A, भू 1 P with (*a.*); मृदूभू, दयार्द्रीभू; प्र-,शम् 4 P, *See* **Melt.** **–ening,** *a.* शांतिद, शांतिकर (री *f.*), शमक-न. **–ly,** *adv.* मृदु, कोमलं, समार्दवं, &c. 2 लघुगत्या, चपलं. 3 निःशब्दं, निभृतं, मंदं, शनैः, शनैः शनैः. **–ness,** *s.* म्रदिमन् *m.*, मार्दवं, सौकुमार्यं, कोमलता, शैथिल्यं, मसृणता, माधुर्यं, &c.

So-ho, *interj.* हंहो, भो भोः.

Soil, *s.* भूः, भूमि *f.*, प्र-,देशः, स्थलं-ली; (earth) मृद् *f.*, मृत्तिका; ' native s. ' जन्मभूमिः; ' fertile s. ' उर्वरा, सर्वसस्याढ्या; ' dry s. ' मरुः, धन्वन् *m.*; ' barren and salt s. ' इ(ई)रिणं; ' waste s ' खिलं, अप्रहतभूमिः; ' stony s. ' शार्करिलभूमिः. 2 मलः-लं, कल्कं, कलुषं-किट्टं, कलंकः –*v. t.* मलिनीकृ 8 U, कलुषयति-मलिनयति-कलंकयति- (D.), दुष् c. (दूषयति). **–ed,** *a.* मलिनित; कलुषित, &c.; कल्किन्, मलिन, समल, लिप्त.

Sojourn, *v. i.* अव-स्था 1 A, स्वल्पकालं निवस् 1 P, प्रवस्, देशांतरं अधि-आ-वस्. प्रवासं-यात्रां-कृ 8 U. **–s., –ing,** *s.* अवस्थानं, अवस्थिति *f.*, यात्रा, प्रवासः, अल्पकालनिवासः; 'the s. of life ' संसारवृत्तिः, संसारयात्रा. **–er,** *s.* आगंतुकः, अवस्थायिन् *m.*, प्रवासी, यात्रिकः, परदेशसेवी.

Solace, *v. t.* सां(शां)त्व् 10, आ-समा-श्वस् c.; परितुष् c.; (oneself) विनुद् c., वि-हृ 1 P. **–s.** सान्त्वनं-ना, आश्वासनं, विनोदः-दनं, क्लेश or शोक-शांति *f.* or अपहरणं; *See* **Comfort, Console.**

Solar, *a.* सौर (री *f.*), सावन (नी *f.*) सूर्य, अर्क (**Sun,** q. v.) in comp.; ' s heat ' सूर्यातपः; सूर्यवंशः, सूर्यग्रहणं, अर्कबिंबं, &c.

Solder, *v. t.* सं-धा 3 U. **–s.** संधिः, धातुलेपः

Soldier, *s.* सैनिकः, योधः, भटः, आयुधिकः योद्धृ *m.* शस्त्र or अस्त्र-धरः-भृत् *m.*-जीविन् *m* -आजीवः, शस्त्र-युद्ध-उपजीवी. **–like,–ly,** *a* सैनिकवत्, सैनिक इव, सैनिकयोग्य. 2 शूर विक्रांत; *See* **Brave.** **–y,** *s.* सेना, बलं, सैन्यं योध-सैनिक-समूहः, भटगणः.

Sole, *a.* एक with एव; एकाकिन्, केवल. –*s* तलं, पादतलं; (of shoe) पादुकातलं. **–ly** *adv.* एक-*a.* with एव or simply एव; केवलं

Solecism, *s.* संस्कारच्युति *f.*, अपप्रयोगः, अशुद्धप्रयोगः, म्लेच्छितं.

Solemn, *a.* पुण्य, पवित्र; विधिपूर्व, संस्कारसहित, धर्मसंस्कारयुक्त. 2 गुरु, गंभीर, धीर उदात्त; (occasion) अलघु, गुर्वर्थ; oft. ex by उत्सव in comp.; ' s. occasions ' उत्सवदिवसाः; 's. procession' यात्रोत्सवः. दृढ; दृढप्रतिज्ञापूर्व, सनिश्चय, स्थिरनिश्चयात्मक; ' a s. promise ' दृढप्रतिज्ञा. **–ity –ness,** *s.* क्रिया, संस्कारः, धर्म-पुण्य-क्रियाविधिः, उत्सवः. 2 गांभीर्यं; गुरुत्वं, गौरवं.

ओलंबर:. -ize, v. t. यथाविधि अनु-ष्ठा 1 P or सं-पद् c., यथाकालं निर्वह् c. 2 गौरवं उत्पद् c. or आहृ 1 P. -ly, adv. यथा विधि, विधिवत्, यथाकालं, विधिपूर्वं. 2 साडंबरं, धीरं, गौरवेण, सगौरवं, गंभीरं, &c.

Solicit, v. t. याच् 1 A, प्र-अभि-अर्थ् 10 ', सविनयं याच् or प्रच्छ् 6 P. -ation, s. याच्ञा, प्रार्थना-ना, याचना, सविनयप्रार्थना. -or, s. याचकः, अर्थिन् m., प्रार्थयितृ m., प्रार्थकः. -ous, a. उत्सुक, सचिंत, सोत्कंठ, व्यग्र, उत्क in comp.; उद्विग्न, चिंताकांत. -ously, adv. उत्सुकं, सोत्कंठं. -ude, s. व्यग्रता, चिंता, उत्कंठा, औत्सुक्यं, उद्वेगः.

Solid, a. ससार, सारवत्, वास्तविक (की f). 2 अशून्य, सगर्भ, पूर्णगर्भ. 3 घन, सु-दृढ, दृढसंधि; सु-संहत, स्थूल, कठिन, संघातवत्; अद्रव; अग्निसंयोगाद् द्रवभावापन्ना काठिन्यविनाशो भवति (S. B. 545) 'lose their s. state' &c. 4 (Knowledge) अबाध, परिपक्व, सुदृढ, सुपरिणत -s. घनः; 's. contents' घनफलं. 2 संघातः, घन-अद्रव-द्रव्यं. -ify, v. t. घनीकृ 8 U, कठिनीकृ. -ity, -ness, s. घनता, काठिन्यं-दृढता, &c.

Soliloquy, s. स्वगत or आत्मगत-भाषण or वचः. -Soliloquize, v. i. स्वगत &c. वच् 2 P, (Say q. v.)

Solitary, a. विविक्त, निर्जन, विजन, निभृत, एकांत; (of persons) विविक्त or एकांत वासिन् or सेविन्, विविक्तप्रिय, एकचर, निःसंग; एक, एकाकिन्, असहाय. 2 Single, q. v. -s. विविक्तवासिन् m., परिव्राज् m. -ily, adv. विविक्त, निभृतं, रहः, उपांशु. -iness, -Solitude, s. विविक्तं, निर्जनं-विजनं-स्थानं, रहःस्थानं, विजनं, अरण्यं. 2 विजनता, निर्जनता, विविक्तता. 3 विविक्ताधिवासः, विविक्तवृत्ति f.-सेवा, संसर्गाभावः.

Solstice, s. अयनांतः, अयनं, अयनकालः-संधिः, क्रांति f.-कालः; ' summer s.' कर्कसंक्रांतिः, उत्तरायणं; 'winter s.' मकरसंक्रांतिः, दक्षिणायनं. -Solstitial, a. (s.) in comp.; 's. point' अयनांतः.

Solve, v. t. व्याकृ 8 U, विवृ 5 U; शुध् c., वि-परि-,° व्या-ख्या 2 P, विशदीकृ, साध्-सिध् c. (साधयति), उप-प्रति-पद् c.; 's. the difficulties' विषमपदानि शोधयति-विमर्शयति. 2 (Question) उत्तरं दा 3 U or वद् 1 P; 's. doubt' संशयं छिद् 7 P or निराकृ or निरस् 4 U or अपनी 1 P. 3 वि-द्रु c., वि-ली c. -ency, s. समृद्धता, ऋणशोधनक्षमता. -ent, a. समृद्ध, सधन, ऋणशोधनक्षम. 2 द्रावण (णी f.), द्रावक. -s. द्रावणं. -Soluble, a. वि-,द्राव्य, विलाप्य, द्रवार्ह. -Solution, s. साधनं, निर्णयं, &c.; व्याख्या, -व्याकरणं, सिद्धि f., उपपत्ति f. 2 द्रावणं, विलयनं. 3 सं-,योगः.

Sombre, a. श्याम, मलिन, धूसर, मंद-मलिन-प्रभ.

Some, a. किम् (कः-का-किं) with चित्, चन, अपि, or अमुक in comp.; 'the son of s. one' अमुकसुतः. 2 (Quantity) किंचित्, कियत्, ईषत्, अल्प, स्वल्प, स्तोक; 'to s. extent' किंचित्, ईषत्, कियताऽंशेन, स्तोकांशेन; 's.-others' एके or केचित्-अन्ये-अपरे. 3 (Number) कतिचित्, कतिपय (यी-या f.); 'going s. steps' कतिचित् पदानि गत्वा; 's. how' कथमपि, केनापि प्रकारेण, कथं कथमपि, कथंचित्, यथाकथंचित्; 's. how or other' येन केन प्रकारेण; 's. one,' 's.-body' कश्चित्, कोपि, यःकश्चन; अमुकः, &c.; 's. thing' यत्किंचित्, किमपि, किंचन, किंचित्; 's.-thing is better than nothing' अकिंचित्कर्मदकरणं श्रेयान्; 's.-time' पूर्वं, एकदा, पुरा, प्राक्, गतकाले, पूर्वकाले; 's.-times' क्वचित, कदाचित्, कदापि, कर्हिचित्; कदा कदा, काले काले; 's.-what' किंचित्; किंचन, अल्पं, स्तोकं; (adv.) किंचित्, ईषत्, स्तोकं, आ pr., देश्य-देशीय-कल्प in comp.; or by doubling adj.; 's.-what red' आताम्र, ताम्रकल्प, ईषद्रक्त; 's.-what afraid' भीतभीत इव; 's.-where' क्वापि, कुत्रचित्, कुत्रापि, यत्र कुत्रचित्, यत्र कुत्रापि.

Somer-sault, -set, s. ऊर्ध्वपादलंघनं.

Somnambulate, v. i. निद्रायां or स्वप्ने चर् 1 P. -Somnambulism, s. निद्राचारः-भ्रमणं, स्वप्नचारः. -Somnambulist, s. निद्राचारः, स्वप्नचारिन् m.

Somniferous, a. स्वाप-निद्रा-जनन (नी f.), निद्राकृत, स्वापकर (री f.).

Somniloquist, s. निद्रालापिन् m., निद्राभाषी.

Somnolent, a. निद्रालु, निद्रालस; See Sleepy.

Son, s. पुत्रः, सुतः, तनयः, सूनुः, आत्मजः, आत्मसंभवः, नंदनः, अंगजः, तनु(नू)जः, दारकः, कुमारः; oft. ex. by deriv.; 's. of Dasaratha' दाशरथिः; गांगेयः, पांडवः, &c.; 's.-in-law' जामातृ m. -less, a. अपुत्र, निपुत्रिक, निःसंतान.

Song, -ster. s. See under Sing.

Sonnet, s. गीतिका, गाथा, लघुगीतं-काव्यं.

Sonorous, a. मधुर, मंजुल. 2 व्यक्त, स्पष्ट, परिस्फुट, व्यक्तवर्ण. 3 विरावित्, उच्च, सुस्वर, झङ्कृत, घोषण, शब्द-ध्वनि-कर (री f.). -ly, adv. मधुरं, स्पष्टं; उच्चैः; महाशब्देन. -ness, s. माधुर्यं, स्पष्टता, उच्चता, सुस्वरता.

Soon, *adv.* अचिरेण, अचिरात्, अविलंबं, आशु, सद्यः, झटिति, सपदि, द्राक्, द्रुतं; *See* **Quickly;** 'as s. as' (so s.), 'no s.-er than' ex. by यावत्-तावत्, च-च, मात्र in comp.; *See* **Scarcely.** **-er,** *adv.* वरं; शीघ्रं; 's. or later' अद्य श्वो वा; 'this is s. said than done' वक्तुं सुकरमिदं न तु कर्तुं.

Soot, *s.* कज्जलं, किट्टं, मसी-षी. **-y,** *a.* कज्जलमय (यी *f.*), धूम्रश्याम.

Sooth, *s.* सत्यं, तथ्यं; 'in s.' सत्यं, नाम, यत्सत्यं, नूनं खलु, सत्यमेव; 's.-sayer' दैवज्ञः, गणकः, मौहूर्तिकः. 's.-saying' शुभाशुभकथनं, दैवपरीक्षा-चिंतनं.

Soothe, *v. t.* शम् c. (शमयति), प्र-उप-°, लघूकृ 8 U, लघयति (D.), निर्वा c. (वापयति); (persons) लल् 10, अनुनी 1 P, सांत्व् 10, प्र-सद् c., परि-तुष् c., आराध् c., परामृश् 6 P (by stroking), आश्वस् c. **-ing,** *a.* शमन (नी *f.*), शांतिकर (री *f.*), शांतिप्रद, निर्वापयितृ, तापहर-हारिन्. **2** सांत्वक, आश्वासनशील; 'by s. words' सांत्वनीगरा, सामवचोभिः. **-s.** प्र-उप-शमनं, निर्वापणं, सांत्वनं, अनुनयः, लालनं.

Sop, *s.* पिंडः, अन्नं, पिष्टकखंडः.

Sophism, Sophistry, *s.* हेत्वाभासः, युक्त्याभासः, पक्षाभासः, आभासः, सत्याभासः, वाक्छलं. **-Sophist,-er,** *s.* हेत्वाभासवादिन् *m.*, तार्किकः. **-ic,-ical,** *a.* आभासरूप, हेत्वाभासरूप, सत्याभास. **-Sophisticate,** *v. t.* **Adulterate,** q. v.

Soporific, Soporiferous, *a.* निद्राजननस्वापन-(नी *f.*), निद्रा-स्वाप-कर (री *f.*), निद्रावह.

Sorcery, *s.* इंद्रजालं, माया, कुसृति *f.*, यातु अभिचारः (black art). **-er,** *s.* ऐंद्रजालिकः, मायाकरः, अभिचारविद्. **-ess.** *s.* योगिनी, मायिनी, अभिचारिणी.

Sordid, *a.* नीच, कृपण, कुत्सित, अधम, दीन, जघन्य, निंद्य; *See* **Mean.** **2** मलिन, मलीमस.

Sore, *s.* क्षतं, व्रणः-णं, अरुस् *n.*, ईर्मं. **-a.** सरुज, जातव्यथ, दुःखित, क्षत, सव्रण; सवेदन, सव्यथ, स्पर्शासह. **2** पीडाकर (री *f.*), कष्ट-क्लेश-प्रद, दुःखद. **3** उग्र, तीव्र, दारुण, गुरु; 's. throat' कंठपाकः, कंठरुज् *f.* **-ly,** *adv.* भृशं, अतीव, नितांतं, उग्रं, दारुणं, सुतरां, बलवत्.

Sorrel, *s.* चुक्रः, सहस्रवेधिन् *m.*, अम्लवेतसः शतवेधी. **-a.** पिंगल, पिशंग.

Sorrow, *s.* शोकः, शुच् *f.*, दुःखं, खेदः. क्लेशः, आधिः, संतापः, आर्ति *f.*, व्यथा; *See* **Grief.** **-v.** *i.* शुच् 1 P, खिद् pass., व्यथ् 1 A; *See* **Grieve.** **-ful,** *a.* सशोक, शोकार्त-आकुल-अन्वित-उपहत-आविष्ट, दुःखित, सतप्त, दुःखिन्, दुःखार्त, उद्विग्न, विषण्ण, दीन, दुर्मनस्, खिन्न, अवसन्न, म्लान, विमनस्. **2** शोच्य, शोचनीय, शोकास्पदीभूत, दुःखावह. **-fully,** *adv.* सशोकं, सखेदं, सोद्वेगं, सदुःखं. **-Sorry,** *a.* दुःखित, दुःखिन्, खिन्न, कष्टापन्न, &c.; *See* **Sorrowful.** **2** दीन, अनु-,शोच्य, कृपण, अनुकंप्य; 's. for one's past conduct' सानुशय, अनुतप्त; 'I am s. to hear this' इदं श्रुत्वा दुःखितोस्मि; 'I am s. to inform you' &c. इति भवते निवेदनं मे दुःखमावहति, निवेदयन्नहं कष्टापन्नोस्मि; 's. horse' कदश्वः; 's. fare' कदन्नं.

Sort, *s.* प्रकारः; विशेषः, भेदः in comp.; जाति *f.*, विधा in comp.; *See* **Manner;** 'a s. of tree' वृक्षविशेषः-भेदः; 'out of s.s' असुस्थ-अस्वस्थ-शरीर. **-v.** *t.* यथाक्रमं-यथावर्गं रच् 10 or विन्यस् 4 U, वर्गक्रमेण न्यस्. **-v.** *i.* युज्-उपपद्-pass., ex. by अनुरूप, युक्त; *See* **Becoming, Proper.**

Sortie, *s.* अवस्कंदः, अवपातः; *See* **Sally.**

Sot,-Sottish, *a.* पानमूढ, पानासक्त, मदोन्मत्त, सदापानरत. **2** **Foolish,** q. v.

Soul, *s.* आत्मन् *m.*; 'individual s.' प्रत्यगात्मा, विज्ञानात्मा; 'rational s.' चिदात्मा 'supreme s.' परमात्मा, ब्रह्मन् *n.*; 'animating s.' जीवात्मा, प्राणः, चेतनः, जीवः; 'embodied s.' देहिन् *m.*, शारीरात्मा, शरीरिन् *m.*, प्राणात्मा, क्षेत्रज्ञः. **2** आत्मा, चेतस् *n.*, चित्तं, मनस् *n.*, हृदयं; *See* **Mind;** 'possessed of a large s. महात्मन्, उदारचेतस्; 'oneness of s.' चित्तैक्यं, ऐक्यभावः; 'the whole s.' सर्वात्मा, सर्वभावः. **3** जीवनं, सारः; तत्त्वं, सार or तत्त्व-भागः or अंशः, सारभूतः. **4** (Self) आत्मा, स्वः. **5** वीर्यं, बलं, उत्साहः, तेजस्. **6** **Person,** q. v. 'the departed s.' प्रेतः, प्रेतनरः; 'heart and s.' प्र-नि-कामं, सर्वात्मना, सर्वभावेन; *See* **Heart;** 'he throws his heart and s. into the work' सुसमाहितेन चेतसा-सर्वात्मना कार्ये प्रवर्तते-व्याप्रियते

Sound, *s.* शब्दः, नि-,नादः, ध्वनिः, नि-,स्व(स्वा)नः, निर्ह्रादः, स्वरः, निनदः, निर्-,घोषः रावः, रवः, वि-संरावः नि-,स्वा(स्व)नः, स्वनितं; 'musical s.' निक्वा(क)णः, क्वणितं; 'confused s.' कोलाहलः, कलकलः, तुमुलरवः; 'rattling s.' रणः, रणितं. **2** संधिसागरः. **-a.** सुस्थ, अरुग्ण, कल्य, निरामय, अनामय, नीरोग, नीरुज, प्रकृतिस्थ व्याधिरहित; (in body) अक्षतशरीर, अविकलेंद्रिय (in mind) अनुपहतचित्त, अविक्लव अव्याकुल, अविक्षिप्त. **2** अक्षत, अजातक्षत. अ

निर्-व्रण, क्षत-व्रण-हीन. 3 ससार, सारवत्, सारगर्भ. 4 अविकल, अन्यून, अखंड, अभिन्न. 5 तीक्ष्ण, तीव्र; निर्भर, प्र-,गाढ, सु-अति pr.; ' s. sleep ' गाढनिद्रा; ' s. beating ' तीक्ष्णदंडः, अतिताडनं. 6 निर्दोष, निश्छिद्र, विशुद्ध, दोषहीन. 7 गाढ, ध(बं)धीर, अगाध, सुपरिणत, परिपक्व. 8 (Argument &c.) अखंडनीय, सप्रमाण, दृढ-सु-प्रमाण, न्याय्य, धर्म्य, युक्तिसिद्ध. 9 (In views) विशुद्धाचार, सत्यमार्गानुयायिन् -v. i. नि-,नद् 1 P, ध्वन् 1 P, स्वन् 1 P, क्वण् 1 P, ह्राद् 1 A, वि-,रु 2 P, स्तन्-रस्-1 P, शब्दं कृ 8 U, शब्दायते (D.). -v. t. ध्वन् c., स्वन् c., नद् c.; वद् c., आ-ध्मा 1 P, सुखमाकर्तन पूर् 10, (trumpet, conch &c.); (drum) तड् 10, आहन् 2 U; ' the drum being s. ed ' आहतायां भेर्यां; (bow) आस्फल् c. 2 परीक्ष् 1 A, सूक्ष्मं-निपुणं-निरूप् 10 or अनुसं-धा 3 U, ज्ञा desid. (जिज्ञासते). 3 उद्-घुष् 10, प्र-ख्या c. (ख्यापयति), प्रकाश् c., प्रकटीकृ; ' s. the depth ' तलं अवगाह् 1 A; ' s. the depth of water ' जलवेधं परि-मा 3 A, 2 P. -ing, a. शब्दन, सुस्वर, शब्दायमान, निनादिन्, निनदत्, घोषण, गर्जत्, निर्ह्रादिन्, शब्दकर (री f.); ' s.-lead ' लंबः, लंबसीसकं. -s. ध्वाननं, शब्दनं, वादनं. 2 वेधपरिमाण, तलावगाहनं. -ly, adv. तीव्रं, तीक्ष्णं, अत्यंतं, प्र-,गाढं; निर्भरं, दृढं, सुखेन, सु-अति pr. -ness, s. स्वास्थ्य, कल्यता, आरोग्यं, अक्षतत्वं, निर्व्रणत्वं, अवैकल्यं, अन्यूनता, अखंडत्वता, निर्दोषता, &c.; ' s. of mind ' चित्तस्वास्थ्यं, अविप्लवः.

Soup, s. जू(यू)षः-षं.

Sour, a. अम्ल, शुक्त, अम्लरस; ' s to the teeth' दंतशठ. 2 कर्कश, परुष, दारुण, रूक्ष, अरुंतुद; सद्वाक्य, वक्र-वाम-शील, कर्कश-स्वभाव, दुष्प्रकृति. -v. t. अम्लीकृ 8 U. 2 कर्कशीकृ, वक्रीकृ. -v. i. अम्लीभू 1 P, कर्कशीभू. -ness, s. अम्लता, कार्कश्यं &c.

Source, s. प्रभवः, योनि f., मूलं, कारणं, हेतुः, प्रकृति f., उद्भवः, संभवः, आदिः, उद्गमस्थानं; *See* **Origin;** ' to have s. in ' प्र-भू 1 P, प्र-,जन् 4 A, उत्पद् 4 A (with abl.); लोभात्क्रोधः प्रभवति, लोभात्कामः प्रजायते (H. 1); ' the s. of the Ganges is in the Himalaya ' हिमवतो गंगा प्रभवति (S. K.).

Souse, v. t. सहसा हृ c. or मस्ज् c. (मज्जयति) or जलेन सिच् 6 P. -v. i. **Pounce,** q. v.

South, s. दक्षिणा, दक्षिणदिक्-दिशा-आशा, अवाची; ' to the s. ' दक्षिणतः, (with gen.). -a., -ern, -erly, a. दक्षिण, अवाच्, अवाचीन, अवाच्य, दाक्षिणात्य; ' in a s. direction' दक्षिणेन (with acc. or gen.); ' s. country ' दक्षिणापथः; ' s.-east ' दक्षिणपूर्वा, आग्नेयी; (a., -ern-erly,) दक्षिणपूर्व, आग्नेय; ' s.-west ' दक्षिणपश्चिमा, नैर्ऋती; (a., -ern, -erly) दक्षिणपश्चिम, नैर्ऋत. -ward, -wards, adv. दक्षिणाभिमुखं, दक्षिणतः, दक्षिणस्यां दिशि.

Souvenir, s. *See* **Memorial.**

Sovereign, s. स्वर्णमुद्रा. 2 अधिराजः, अधीश्वरः, अधिपतिः, महाराजः, अधीशः, सार्वभौमः, नृपतिः, सम्राज् m., oft. by राजा, पालः, नाथः, &c.; *See* **King.** -a. परम, श्रेष्ठ, मुख्य, प्रमुख; *See* **Principal.** 2 उत्कृष्ट, गुणावह (medicine &c.); ' s. medicine' परमौषधं, महौषधं. -ty, s. प्रभुत्वं, राज्यं, आधिपत्यं, साम्राज्यं, ईशत्वं, स्वाम्यं, ईश्वरत्वं, इंद्रता in comp.; ' s. of beasts ' मृगेंद्रता. 2 (Authority) मुख्य-श्रेष्ठ-अधिकारः, प्रधानाधिकारः.

Sow, s. सू(शू)करी, वराही, कोली. -v. t. वप् 1 P, आ-,नि-°, (बीजानि) विकॄ 6 P, आरुह् c.; ' s. dissensions ' भेदं जन् c., भेदबीजानि वप्; ' s. dragon's teeth ' कलहबीजं वप्; 'as you s., so you reap' यो यद्वपति बीजं हि सोपि तत्प्रभते फलं; *See* also **Reap.** -er, s. वप्तृ m., वापिन् m. वापकः. -ing, s. वपनं, वापः, उप्ति f., बीजारोपणं.

Space, s. आकाशः-शं, शून्यं, दिगंतरं, रिक्तं, अंतरिक्षं, नभोमंडलं; 'infinite s.' अनंतं, महाकाशं; 'finite s.' घटाकाशं. 2 (Intervening s.) अंतरालं, मध्यं, अभ्यंतरं, अंतरं, अभ्यंतरावकाशः, व्यवधानं. 3 अवकाशः, अवसरः, प्रसरः, विषयः, स्थानं, स्थलं, भूमि f. 4 प्र-,देशः, दिश्-शा, दिग्भागः; 'pervading all s.' सर्वदिग्व्यापिन्, अभिव्यापिन्. 5 अंतरं, अध्वन् m., देशः; 's. of time' अंतरं, अवधिः, कालावधिः, कालांतरं; oft. ex. by अभ्यंतरं; 'in the s. of six months ' षण्मासाभ्यंतरे. -Spacious, a. विस्तीर्ण, विशाल, विपुल, विस्तृत, पृथु; *See* **Large.** -ness, s. विस्तारः, विस्तृति f., वैपुल्यं.

Spade, s. खनित्रं, अवदारणं, स्तंबघ्नः.

Span, s. किष्कु-वितस्ति-m. f.; ' life's s. ' जीवितावधिः; gen. ex. by words for 'Transitory ' q. v.; 'the s. of life is short ' आयुः कल्लोललोलं (Bh. II. 82), कतिपयनिमेषायुषि जने (सति)) (Bh. II. 40); जीवितं तरलं &c. -v. t. प्र-परि-मा 3 A, 2 P.

Spangle, s. रजतपत्रं, धातुतारा -v. t. **Adorn,** q. v.

Spank, v. t. चपेटेन प्रह् 1 P or तड् 10. -v. i. सवेगं चल् 1 P or विसृप् 1 P.

Spar, s. स्फटिकगुलिका. 2 दीर्घयष्टि f.-काष्ठं, दारुखंडः, -v. i. परिहासेन मुष्टीमुष्टि युध् 4 A.

Spare, *v. t.* रक्ष् 1 P, सं-चि 5 U, (money); न व्यय् 10 (व्यययति) or विक्षिप् 6 P, परिमितं प्र-विनि-युज् 7 A, 10; 'does not s. time' कालं विक्षिपति-हरति; 'will you s. three hours for me' अपि भवान्मदर्थे प्रहरमेकं विनियोजयिष्यति. 2 मुच् 6 P, (वधात्, छेदात् &c.), त्यज् 1 P, हा 3 P, वि-उत्-सृज् 6 P. 3 उपेक्ष् 1 A, न :अपेक्ष्, सुखेन त्यज्; oft ex. by 'not' with other words; 'but s. this tree' इमं वृक्षं तावन्मा छिंद्धि; 's. him' मुच्यतामसौ, न हंतव्यः; 'he can now be s. ed from my service' तस्य सेवया न मे प्रयोजनमधुना, तस्य सेवां नापेक्षे; *See* **Dispense. 4** अव-,शिष् c., उद्-वृत् c. —*a.* उद्वृत्त, अभ्यापृत, अधिक, अतिरिक्त. अव-,शिष्ट. **2** अल्प, स्तोक, परि-,मित, अबहुल. **3** क्षाम, कृश. परि-,क्षीण, निर्मांस, शुष्क; *See* **Lean.** **-ing,** *a.* मितव्यय, अल्प-परिमित-व्ययिन्; परिमित, अल्प; 's. of words' अल्पभाषिन्; परिमितालाप. **-ingly,** *adv.* मितं, अल्पं, मितव्ययेन, अल्पशः, स्तोकशः; 'eating s.' मिताहार, मितभुज्. **-ness.** *s* कृशता, क्षीणता.

Spark, *s.* वि-,स्फुलिंगः अग्नि or ज्वलन-कणः or कणिका; कणः, कणिका, लवः, लेशः, अणुः. **2 Fop,** q. v. **-Sparkle,** *v. i.* स्फुर् 6 P, प्र-वि-°, तेजःकणान्-स्फुलिंगान्-उत्क्षिप् 6 P or विकृ 6 P; *See* **Shine** also; 's.-ing fitfully' क्षणनष्टदृष्टाः (Mr. 5.). **-ing,** *a.* स्फुरत्, स्फुरितप्रभ, दीप्तिमत् &c.; 's. wit' पुरःस्फुरंती मतिः, मतिविलासः

Sparring, *s.* मुष्टियुद्धं, मुष्टीमुष्टि युद्धं **2** विचारः

Sparrow, *s.* चटकः, कलविंकः; 'female s.' चटका.

Sparse, *a.* विरल, अबहुल, अनिबिड.

Spasm, *s.* (अंग) संकोचः, आक्षेपः, आकर्षः, उद्वेष्टनं, व्यासः; 's. in the leg' पिंडिकोद्वेष्टनं; शूलं (with pain). **-Spasmodic,** *a.* सोद्वेष्टन, आकर्षिन्, आक्षेपक, by (*s.*); 's. contraction' आकर्षः, संकोचः.

Spatter, *v. t.* अवसिच् 6 P or अवकॄ 6 P. (पंकादिना.)

Spattle, Spatula, *s.* प्र-वि-लेपनी.

Spavin, *s.* संधिशोथः.

Spawl, *s.* निष्ठ्यूतं; *See* **Saliva.**

Spawn, *s.* अंडं, मीनांडं, भेकांडं, &c. **-v.** अंडानि मोक्ष् 10 or प्रसू 2, 4 A.

Speak, *v. t.* वद् 1 P, वच् 2 P, भण्-गद् 1 P, भाष् 1 A, ब्रू 2 U, आलप् 1 P; *See* **Say;** वाचं-गिरं-उदीर् c. or उद्-गॄ 6 P; 's. of' अभि-धा 3 U. कथ् 10, निर्दिश् 6 P, वर्ण् 10; 's. ill of' अपभाष्, परि-अप-वद् 1 A, निंद् 1 P; 's. out' स्पष्टं-स्फुटं-वद्, प्रकाशं ब्रू; 's. well of' प्रशंस् 1 P; *See* **Praise;** 's. with,' 's. together' संवद्, संभाष्, संमंत्र् 10 A. **-er,** *s.* प्रवक्तृ *m.*, वाग्मिन् *m.*, वाग्विद् *m.* **-ing,** *s.* भाषणं, भाषितं, वचस् *n.*, उक्ति *f.*, व्याहारः; *See* **Speech** below. **-Speech,** *s.* वाच् *f.*, वाक्शक्ति *f.*, वाणी, गिर् *f.* **2** वाक्, वचः, गीः, वाणी, उक्तिः, व्याहारः, भाषणं, वचनं, आलापः, वाक्यं, भारती, सरस्वती, व्याहृति *f.* **3** भाषा, उक्तिः; 'eloquence of s.' शब्द-पद-लालित्यं; 'covert s.' भंगिभाषणं, व्याजोक्तिः; 'openig of s.' वाङ्मुखं; 'goddess of s.' वाग्देवी, भारती, सरस्वती; 'part of s.' शब्दजातिः-भेदः. **-ify,** *v. i.* **Harangue,** q. v. **-less,** *a.* मूक, वाग्हीन, स्तंभितवाक्. *See* **Mute.**

Spear, *s.* शूलः-लं, कुंतः, प्रासः, तोमरः, शक्ति *f.*, शल्यं; 'head of a s.' फलं, शूलाग्रं; 's.-man' शूलिन् *m.*, शूलधरः-भृत्, शूलपाणिः, प्रासिकः, कौंतिकः, शाक्तीकः, शक्तिधरः-ग्रहः. **—v. t.** शूलेन व्यध् 4 P.

Specie, *s.* मुद्रा, नाणकं.

Species, *s.* जाति *f.*, प्रकारः, भेदः, विशेषः; 'of the same s.' स-एक-जातीय; 'a s. of animal' प्राणिविशेषः-भेदः; 'genus and s.' —सामान्यविशेषौ. **-Special,** *a.* विशेष in comp., असामान्य, असाधारण (णी *f.*), अव्यापक, वैशेषिक (की *f.*), विशिष्ट, अवच्छेदक; 's. duty' विशेषधर्मः; विशेषनियमः, समयविशेषः, &c. **2** लोकोत्तर, लोकबाह्य. **3** तद्धेतुक, तन्निमित्तक, तदुद्दिष्ट. **4** जातिवाचिन्, जाति in comp.; 's. characteristic' जातिधर्मः-लक्षणं. **-ly,** *adv.* विशेषतः, विशेषेण; सविशेषं, कार्यतः, प्रयोजनापेक्षया. **-ity,-ty,** *s.* विशेषः, विशेषधर्मः, विशिष्टता. **-Specific-, -al,** *a.* विशेष, जाति in comp.; विशिष्ट, असामान्य, जातिव्यक्ति-गत; 's. gravity' विशिष्टगुरुत्वं; 's. character' जाति-विशेष-धर्मः-लक्षणं. **-s.** 's. medicine' अमोघगुणमौषधं, विशिष्टौषधं. **-ically,** *adv.* जातितः, विशेषतः, सविशेषं. **-Specify,** *v. t.* (सविशेषं) निर्दिश् 6 P, कथ् 10, अभि-धा 3 U, उदाहृ 1 P. विशिष् 7 P or c., एकैकशः परिसं-ख्या 2 P or कथ्; विशेषं कथ् or ब्रू 2 U, अवच्छिद् 7 P. **-ied,** *a.* निर्दिष्ट, अवच्छिन्न, निर्दिष्ट-उक्त-लक्षण &c.; 'will be s. further on' अग्रे वक्ष्यते. **-ication,** *s.* विशेषनिर्देशः-कथनं-वर्णनं, व्यवच्छेदः, परिसंख्या, विशेषः.

Specimen, *s.* आदर्शः, प्रतिमा, प्रतिरूपं.

Specious, *a.* सत्यसंकाश-आभास-सन्निभ, आपातरमणीय, बहिः रमणीय, सुदृश्य, बहिरेव मनोरम. **-ly,** *adv.* सत्याभासपूर्वं. **-ness,** *s.* सत्याभासः.

Speck, Speckle, *s.* बिंदुः, चिह्नं, अंकः, कलंकः; तिलकः-कं. 2 शकलः-लं, कणः, लवः, अणुः, सूक्ष्मबिंदुः, 's. s of clouds' मेघशकलानि. -*v. t.* चित्र् 10, चित्री-कर्बुरी-कृ 8 U; बिंदुभिः चित्र्. **-ed,** *a.* चित्र, चित्रित, कर्बुरित, चित्रविचित्र, बिंदुचित्रित-चिह्नित, शबलीकृत, चित्रांग (-गी *f.*); 'having a s. belly' चित्रोदर, पृषदुदर.

Spectacle, *s.* दृश्यं कौतुकं, आलोकः, चमत्कारः, स्थानं दृष्टिविषयः. 3 (S.s) उपनेत्रे, दृष्टिसहायौ.

Spectator, *s.* प्रेक्षकः, प्रेक्षकजनः-लोकः, द्रष्टृ *m.*; (in an audience &c.) पारिषद्यः, सामाजिकः, पार्षद्‌ः.

Spectre, *s.* भूतः, पिशाचः, छाया, वेतालः, प्रेतः; 'to raise a s.' वेतालं उत्था c., छायां उद्ध c.

Specular, *a.* आदर्शगुणक.

Speculate, *v. i.* विचर् c., वितर्क् 10, विमृश् 6 P; *See* **Consider. 2** बहुलाभापेक्षया क्री 9 U; अविचारेण दैवाधीनं कर्म कृ 8 U. **-ion,** *s.* विचारः, वितर्कः, विमर्शः, परिकल्पना. 2 कल्पना, प्र-,युक्ति *f.*, उपायः. **-ive,** *a.* विचारवत्, विचार-ध्यान-शील. 2 काल्पनिक-मानसिक- (की *f.*), अव्यवहार्य, अप्रवर्तनीय, अव्यवहारानुरूप, व्यवहारायोग्य. **-or,** *s.* कल्पकः, विचारकः. 2 **Philosopher,** q. v.

Speculum, *s. See* **Mirror.**

Speed, *s.* वेगः, प्र-,जवः, रंहस् *n.*, रयः, जवनं, त्वरा, रभसः, तरस् *n.*, शीघ्रता, तूर्णि *f.* -*v. i.* त्वर् 1 A, शीघ्रं-सवेगं गम् or चल् 1 P. 2 सिध् 4 P, सफलीभू 1 P, *See* **Prosper, Succeed. 3 Fare,** q. v. -*v. t.* त्वर् c. (त्वरयति). 2 पुरस्कृ, उपकृ, सिध् c. (साधयति); शुभं-कल्याणं-कृ 8 U. **3 Ruin, Kill,** q. v.; 'God s. !' शिवास्ते पंथानः संतु (P. 1. 1), शिवस्ते पंथाः भूयात् (S. 4); विजयी भव. **-Speedy,** *a.* शीघ्र, त्वरित, सत्वर, अविलंबित, द्रुत, सजव, वेगवत्, जवन, महावेग, शीघ्रगति; *See* **Prompt** also; better by 's.-ly'. **-ily,** *adv.* आशु, शीघ्रं, सत्वरं, झटिति, त्वरितं, तूर्णं, अविलंबं, सपदि. 2 सरभसं, सवेगं. **-iness,** *s.* जवनता, वेगवत्त्वं, शीघ्रता &c.

Spell, *s.* मंत्रः, अभिचारमंत्रः (magic); मोहनं, आकर्षणं; 's.-bound' अभिमंत्रित, मंत्रवद्धवीर्य. -*v. t.* अभिमंत्र् 10 A, अभिचर् c., मंत्रैः वशीकृ 8 U, वि-,मुह् c. 2 अक्षराणि निर्दिश् 6 P, यथाक्षरं सं-रूपा 2 P or पठ् 1 P or लिख् 6 P. **-ing,** *s.* वर्ण or अक्षर-वि न्यासः or रचना; 'having a double s.' द्विरूप; 'variation in s.' पाठांतरं, पाठभेदः.

Spend, *v. t.* उत्-वि-सृज् 6 P, परि- त्यज् 1 P, व्यय् 10 (व्यययति), विनि-युज् 7 A, 10; 'good men, like clouds, take (things) for s. ing (them), आदानं हि विसर्गाय सतां वारिमुचामिव (R. iv. 86); 's.-ing on proper objects' पात्रे व्ययः. 2 अव-,सद् c, क्षि 5 P or c., नश् c., अप-चि 5 U, क्षीणीकृ 8 U, विक्षिप् 6 P; *See* **Exhaust;** 'spent with toil' श्रमखिन्न, श्रमावसन्न. 3 (Time) क्षै c. (क्षपयति), गम् c., नी 1 P, या c., अतिवह् c.; *See* **Pass;** 's. in, vain' क्षिप्, ह 1 P. **-ing,** *s.* व्ययः, वि-उत्-सर्गः, त्यागः, विनियोगः; यापनं, हरणं, विक्षेपः **-Spendthrift,** *s.* अतिव्ययिन् *m.*, त्यागशीलः, मुक्तहस्तः, अर्थनाशिन् *m.*

Sperm,-atic, *See* **Semen,** &c.

Spew, *v. t.* वम् 1 P, छर्द् 10, नि-,ष्ठिव् 1, 4 P.

Sphere, *s.* गोलः-लं, वर्तुलं, मंडलं; *See* **Orb;** 'celestial s.' व्योम-नभो-मंडलं. 2 नियोगः, विषयः, अधिकारः, धर्मः, प्रकरणं. 3 सं-,स्थिति *f.*, अवस्था, दशा, (in life). **-Spherical,** *a.* गोलाकार, वर्तुल, गोल. **-Spheroid,** *s.* उपगोलः; अंडाकृतिः. **-al,** *a.* गोलप्राय-कल्प, उपगोल. **-Spherule,** *s.* गोलकः, लघु-क्षुद्र-गोलः.

Sphygmograph, *s.* नाडीस्फुरण (स्पंदन)-लेखनयंत्रं.

Spice, *s.* गंधद्रव्यं; 'the three s. s.' त्रिजातकं. -*v. t.* वास् 10, अधि-सु-°. **-ed,-y,** *a.* वासित, सगंध, सुगंध, मिष्ट, सुरस.

Spider, *s.* तंतुवायः, तंतुनाभः, तंत्रवायः, ऊर्णनाभः, लूता, मर्कटकः, जालिकः, कोश(ष)-कारः, अष्टापदः.

Spike, *s.* शस्यमंजरी; कणिशः-शं, धान्यशीर्षकं. 2 महाकीलः, शंकुः, शूलः-लं, कंटकः, -*v. t.* कील् 10. **-ed,** *a.* शंकुयुक्त; कीलित, शंकुबद्ध. **-y,** *a.* तीक्ष्णाग्र, सूच्यग्र, कीलनिचित.

Spikenard, *s.* जटामांसी, तपस्विनी, जटिला लोमशा, म(मि)सि-सी-षि-पी *f.*, नलदा.

Spill, *s.* शलाका. -*v. t.* (अकस्मात्) अधः क्षिप् 6 P; अव-, पत् c., निः-,स्रु c.; 's. blood' रुधिरं स्रु c., रक्तपातं कृ 8 U. -*v. i.* स्रु 1 P, पत् c. pass.

Spin, *v. t.* (तंतून्) कृ 8 U, अन् c., तन् 8 U, सृज् 6 P, वे 1 P, कृत् 6 P; 'the spider s. s out its web (threads) from itself' तंतुनाभः स्वत एव तंतून् सृजति (S. B. 477). 2 निष्कृष् 1 P, निर्मा c. 3 परिवृत् c. परि-,भ्रम् c., घूर्ण् c. -*v. i.* भ्रम् 1, 4 P, परिवृत् 1 A. **-ner,** *s.* तंतुवायः-यः, कर्तकः. **-ing,** *s.* तंतुवायः वायः, तानवं, तंतुकरणं.

Spindle, *s.* तर्कु *f.*, तर्कुटी-टं; 's.-shanked' क्षामजंघ, पृश्नि, दीर्घजंघ.

Spine, *s.* पृष्ठवंशः, कशेरु *m. n.*, कशेरुका, पृष्ठास्थि *n.*

Spinous,-Spiny, *a.* सकंटक.

Spinster, *s.* सूत्रकर्त्रिका. 2 अनूढा, अविवाहिता.

Spiracle. *s.* छिद्रं, सूक्ष्मरंध्रं, वायुमार्गः.

Spire, *s.* व्या-आ-वर्तनं, आवर्तः, व्यावर्तनरेखा. 2 शिखरं, शृंगं, शिखा. **-al,** *a.* वि-,आवर्तिन्, चक्राकार. **-ally,** *adv.* चक्राकारेण.

Spirit, *s.* प्राणाः, असवः,(pl.). 2 आत्मन् *m.*, देहिन् *m.*, क्षेत्रज्ञः; *See* **Soul;** the supreme s.' परमात्मा, ब्रह्म. 3 चित्तं, मनस्-चेतस्- *n.*, वृत्ति *f.*, भावः; 'low-s.-ed' लघुचेतस्, क्षुद्रमनस् 'proudness of s.' चित्तसमुन्नति *f.*, चित्तोद्रेकः; *See* **Pride;** 'in good s.s'. 'in high s.s' सोल्लास, महृष्ट, प्रमुदितचित्त; हर्षवृत्ति; 'high s. s.' उत्साहः, उल्लासः, प्रफुल्लता, प्रहर्षः; 'low s. s' विषादः. उद्वेगः; 'in low s. s' उद्विग्न, विषण्ण, उदासीन; *See* **Dejected.** 4 सत्त्वं, तेजस् *n.*, वीर्यं, प्रभावः, ऊर्जः, उत्साहः. 5 भावः. भावार्थः, उद्देशः; 'he obeyed my order in s. only' भावार्थमेव गृहीत्वा ममाज्ञामनुष्ठितवान्. 6 सारः, तत्त्वं, सत्त्वं, सारांशः, जीवितं; जीवनं; 'Ojas is the s. (soul) of prose' ओजः गद्यस्य जीवितं (Kav.). 7 प्रकृति *f.*, शीलं, स्वभावः, वृत्तिः; 'gentle s.' स्वभावसौजन्यं, शांतशीलता; 'of a noble s.' उदारप्रकृति. 8 भूतः, वेतालः; 'evil s.' रक्षस् *n.*, राक्षसः, पिशाचः, अपदेवता. 9 प्रेतः, परेतः, छाया. 10 (Of style) ओजस् *n.*, ऊर्जः; रसः. 11 (S. s) सुरा, मद्यं; *See* **Liquor.** **-v.** *t.* (up) आश्वस् c., उज्जीव् c., उत्तिज् c. **-ed,** *a.* सत्त्ववत्, सोत्साह, तेजस्विन्, वीर्यवत्, ससत्त्व; 'a s. speech' ऊर्जिताश्रयं वचनं. 2 ओजस्विन्, सरस. **-edly,** *adv.* सोत्साहं, ससत्त्वं. **-less,** *a.* निःसत्त्व, तेजोविहीन; निस्तेजस्, निर्वीर्य, नीरस. **-uous,** *a.* मादिन्, मादक; 's. liquor' सुरा, मदिरा, &c. **-Spiritual,** *a.* अध्यात्म in comp., (अध्यात्मज्ञानं), आध्यात्मिक (की *f.*), निरवयव, निराकार, चिद्रूप, अमूर्त, परम. 2 पारत्रिक-पारलौकिक-पारमार्थिक-(की *f.*), मानसिक-सात्त्विक-(की *f.*). 3 धार्मिक(की *f.*), धर्म in comp.; असांसारिक-अलौकिक-(की *f.*): 's. preceptor' उपाध्यायः; 's. father' धर्मतातःपितृ *m.* **-ism,** *s.* ब्रह्मवादः, ज्ञान-निवृत्तिमार्गः. **-ist,** *s.* ब्रह्मवादिन् *m.* **-ity,** अमूर्तता, असांसारिकता, परमार्थनिष्ठा. **-ly,** *adv.* परमार्थबुद्ध्या, परमार्थतः; 's. minded' परमार्थवृत्ति-बुद्धि, परमार्थासक्त. ब्रह्मनिष्ठ संसारव्यावृत्त.

Spit, *v. t.* नि-,ष्ठिव् 1, 4 P, उद्वम् 1 P, मुखात् सृ c.,उद्-गॄ 6 P. 2 शूला कृ 8 U, शूले आरुह् c. **-v.** *i.* ष्ठिव्, श्लेष्माणं-लालां निःसृ. **-s.,** **-ting,** *s.* निष्ठ्यूति *f.*, नि-,ष्ठीव-वनं, उद्वमनं, उद्गिरणं; 's. ing-pit, spittoon' प्रतिग्राहः, पतद्ग्रहः. 2 शूलः-लं; 'roasted on a s.' शूल्य, शूलाकृत, भटित्र. **-Spittle,** *s.* नि-,ष्ठ्यूतं, ष्ठीवनं, मुखस्रावः, लाला; *See* **Saliva.**

Spite, *s.* वि-,द्वेषः, ईर्ष्या, असूया, द्रोहः, मात्सर्यं; 'in s. of' अनादृत्य (with acc.), gen. or. by gen. or loc. abs.; पश्यतोपि गुरोः, तिष्ठत्सु लोकपालेषु वृणुते नलं पतिं; 'snatches away, in s. of our looking on' मिषतां नः आच्छिनत्ति (K. II. 46). **-v.** *t.* वि-,द्विष् 2 U; द्रुह् 4 P, ईर्ष्य् 1 P (with dat.). **-ful,** *a.* सासूय, विद्वेषिन्, मत्सरिन्, सेर्ष्य, द्रोहबुद्धि, दुष्टभाव; *See* **Malicious. -fully,** *adv.* सासूयं, द्वेषात् द्वेष-द्रोह-बुद्ध्या, सेर्ष्यं, मात्सर्यात्.

Splash, *v.* आस्फल् c., (आस्फालितं यत्प्रमदाकराग्रैः R. XVI. 13), क्रीडायां तड् 10; इतस्ततः विक्षिप् 6 P. **-s.,** **-ing,** *s.* आस्फालनं, विक्षेपः, आस्फालनशब्दः-नादः; 'the log fell down with a s.' काष्ठखंडः पतितो जलमास्फालयत्.

Spleen, *s.* प्लीहन् *m.*: प्लीहा, गुल्मः; 'enlargement of the s.' प्लीहाभिवृद्धि *f.*, प्लीहोदरं. 2 संरंभः, मन्युः; 's.-wort' प्लीहघ्नः, प्लीहशत्रुः. **-Splenetic,** *a.* प्लीहरोगिन्. 2 वक्र-कर्कश-शील, पिशुन, कर्कश.

Splendid, *a.* भासुर, उज्ज्वल, भास्वत्, अतितेजस (सी *f.*), अतिशोभन, सुप्रभ, अतिप्रभ, अतिदीप्तिमत्; महातेजस्; 'a s. dress' उज्ज्वलवेशः. उदारनेपथ्यं. 2 श्रेष्ठ, प्रशस्य, परम, विशिष्टतम,अभिनंद्य,(success). 3 महाप्रताप, प्रतापवत्; *See* **Majestic. -ly,** *adv.* उज्ज्वलं, सुप्रभं, अतिशोभया, अतिप्रतापेन; 's. dressed' उज्ज्वलवेशधारिन् **-Splendour,** *s.* शोभा, तेजस् *n.*, श्रीः, प्रभा, औज्ज्वल्यं, भासुरत्वं, अति-शोभा-कांति-दीप्ति *f.*, महातेजः, प्रतापः, विभूति *f.*, वैभवं.

Splice, *v. t.* संयुज् 7 U, 10.

Splint, -er, *s.* (काष्ठ-) खंडः, शकलं, विदलं, भिन्नं. **-v.** *t.* वि-दॄ 9 P or c.; *See* **Tear. -v.** *i.* वि-दल् 1 P, स्फुट् 6 P, विभिद् pass.

Split, *v. i.* स्फुट् 6 P, वि-,दल् 1 P, भंज्-विभिद्-विद्-pass., त्रुट् 4, 6 P, शकलीभू 1 P, **-v.** *t.* स्फुट् c., वि-,दॄ 9 P or c.. वि-,पट् 10, वि-,भिद् 7 P or c., भंज् 7 P, खंड् 10, वि-,छिद् 7 P, त्रुट् c., विदल् c. (दलयति), शकलीकृ 8 U. **-s.** वि-,भेदः, भंगः विदरः, स्फु(स्फो)टनं,

भिदा, छिद्रं, रंध्रं. -ting, s. विदारणं, विपाटनं, विद्दलनं, &c.

Spoil, v. t. मलिनीकृ 8 U, कलुषी-आविलीकृ, मलिनयति-कलुषयति-आविलयति (D.), दुष् c. (दूषयति), (fig. also), विकृ; विप्रकृ; भ्रंश् c. (सत्यधात्). 2 अत्यंतं लल् 10, अत्यंतं छंदं अनुवृत् 1 A or अनुरुध् 4 A. 3 लुंट् 1 P, 10, अप-हृ 1 P. 4 नश् c.. उद्-विध्वंस् c., उच्छिद् 7 P, दुष् c. -v. i. दुष् 4 P, नश् 4 P. -s. युद्धलब्धं धनं, लुंठितं लोत्रं, लोप्त्रं, अपहारः, 's. of cattle' गोग्रहः. -ed, -Spoilt, a. दूषित, मलिनीकृत, नाशित, उच्छिन्न. 2 अतिलालित, दुर्ललित; लालनात् दूषित. -er, s. अपहारकः, लुंठाकः, दूषकः, उच्छेदकः.

Spoke, s. अरः-रं, सक्थि n.; 's. s are fixed on to the nave' नाभौ अराः प्रतिष्ठिताः; 'a wheel having long s. s' दीर्घसक्थि चक्रं.

Spokesman, s. मुखं, (त्वं मम मुखं भव V.1) वक्तृ m.

Spoliate, v. t. लुंट् 1 P, 10, अपहृ 1 P -ion, s. अप-हारः- हरणं, लुंठनं.

Sponge, s. **Sponger,** q. v. -y, a. विरल-शिथिल-अवयव. -Sponger, s. परान्नपुष्टः, परपिंडादः, पात्रेसमितः.

Sponsor, s. धर्मप्रतिभूः-प्रतिनिधिः.

Spontaneous, a. यादृच्छिक-ऐच्छिक-(की f.), स्वेच्छानुरूप, स्वतःप्रवर्तित, यदृच्छा or स्वेच्छामूलक or पूर्वक, कामहेतुक, अयत्नकृत-कृत, यदृच्छा-स्वेच्छा-काम-in comp. -ly, adv. स्वेच्छातः, स्वेच्छया, यदृच्छया, स्वेच्छानुसारेण, स्वयं, स्वतः, स्वेच्छापूर्वं, कामतः, अंतःप्रवृत्त्या, अयत्नेन, सहजावबोधेन. -ness, -Spontaneity, s. यदृच्छा, स्वेच्छा, कामः, रुचिः f.

Spoon, s. चमसः-सं, कंबि-बा f., दर्वि-र्वी f., शलाका; See **Ladle;** 'Wooden s.' दारुहस्तकः, दर्वि m. -ful, s. Ex. by (s.); 'two s. s' दर्वीद्वयं, चमसद्वयमात्रं.

Spoor, s. श्वापदपदवी, वनपशुपद्धति f.

Sporadic, a. See **Single.**

Sport, v. i. क्रीड् 1 P, क्रीड् 1 P, विलस् 1 P, रम् 1 A, खेल् 1 P. 2 मृगयां कृ 8 U, आखेटोद्यमं कृ. 3 परिहस् 1 P. -s. विहारः, क्रीडा, खेला, केलि m. f., लीला, विलासः; 'boys' s.' कूर्दनं, क्रीडा, लीला. 2 मृगया, आच्छोदनं; आखेटः; 'to make the better s.' मृगयारसं वर्धयितुं, मृगयां अधिकफलवतीं कर्तुं. 3 अव-उप-हासः; विडंबना; See **Mockery.** 4 परिहासः, लीला, केलिः, नर्मन् n.; 'in s.' परिहासेन, लीलया; 'uttered in s.' नर्मालापः, परिहासजल्पितं. -ive, a. (Of persons) क्रीडाशीलपर, विलासपर, खेलपर, विहारिन्, विहारकेलिप्रिय; See **Playful.** 2 उपहासपर्ण, नर्मभाव, सपरिहास. 3 सविलास सलील,

सहेल, सखेल, उल्लसित. -ively, adv. सखेलं, लीलया, सलीलं, सविलासं. -s man, s. मृगया-सेविन् m.- विर गोलः, मृगयुः, व्याधः, लुब्धकः, शकुनिः ...कः.

Spot, s. स्थानं, स्थलं, पदं, प्र-देशः, आस्पदं, भूमि f., क्षेत्रं; 'on the s.' तत्रैव. 2 बिंदुः, अंकः, लांछनं, चिह्नं, लक्षणं, पदं; 's. on the body' तिलकः-कं; 's. on the moon' लक्ष्मन् n., अंकः. 3 कलंकः, दूषणं. -v. t. बिंदुभिः चित्र् 10 or चित्रयति (D.), कर्बुरीकृ 8 U, शबलीकृ, कल्माषयति (D.); oft. by चित्र-a.; 's.-ted deer' चित्रो मृगः, बिंदुलांछितो मृगः, चित्रांगः, कर्बुरितगात्रः, &c. 2 कलंकयति (D.), दुष् c. (दूषयति). 3 Soil. Spoil, q. v. -less, a. निष्कलंक, अकलंक, विशुद्ध, निष्कल्मष, निर्मल, अकलुष, अमलिन; अनिंद्य, निरवद्य, अनघ.

Spouse, s. परिग्रहीतृ m., परिणेतृ m., वरः, भर्तृ m., पतिः. 2 भार्या, वधूः; See **Wife.** -al, s. विवाहः, परिणयः, पाणिग्रहणं-ग्रहणं; See **Marriage.**

Spout, s. नाली, प्रणालः-ली. -v. t. उत्क्षिप् 6 P, उद्वम् 4 U, बलवत् निपत् or निःसृ c. or उत्क्षिप् (fig.), उद्गॄ 6 P, उद्वम् 1 P, निःसृ c., विसृज् 6 P. -v. i. सवेगं उद्वम् 1 P or निर्गम्, निःसृ 1 P. उत्क्षिप्-उत्क्षिप् pass.

Sprain, v. t. अति श्लेष (संधीन् &c.) वितन् 8U, आक्षिप् 6 P, अभिहन् 2 P. -s. संध्यभिघातः, स्नायु वेतानः, अतिविस्तारः.

Sprat, s. नल-सल-मत्स्यः.

Sprawl, v. i. सांगविक्षेपं स्वप् 2 P.

Spray, s. शीकरः, सीकरः, तुषारः; 'bearing s. s' शीकरिन्, शीकरासारवाहिन्. 2 विटपः, शाखा, प्रशाखिका

Spread, v. i. प्र-वि-सृ 1 P, प्र-वि-सृ 1 P, वितन्-विस्तृ-विस्तॄ-pass., व्याप् 5 P, विजृंभ् 1 A, प्रचर् 1 P; (disease) संक्रम् 1 U, 4 P, संचर्, वि सृप्, प्रवृत् 1 P, प्रथ् 1 A. -v. t. स्तृ 5 U, स्तॄ 9 U or c., वि-सं-आ-°; अव-वि-कॄ 6 P, (net &c.); वि-प्र-सृप् c., वि-प्र-सृ c., तन् 8 U, प्र-वि-सं-आ-°, प्रवृत् c. 2 (Opinions &c.) प्र-चर् c., सं-प्र-चार् c., प्रथ् c., प्रकाश् c., बहुलीकृ 8 U. -s. प्रसारः, प्रसरः, अभि-वृद्धि f., प्रवर्तनं, विस्तारः. -ing, a. प्र-वि-सारिन्, प्रसर्पिन्, प्रतानिन्, प्ररोहिन्; 's. creeper is वीरुध्' लतावतानिकी वीरुध्. -s. प्रसरः, विसर्पणं, विततिः f., प्रतानः, प्रवर्धनं.

Sprig, s. विटपः, शाखा, पल्लवः-वं, वृंतं, उपशाखा.

Sprightly, a. उत्साहवत्, पटु, -सोत्साह, सोल्लास, प्रहृष्ट, उल्लसित, उत्साहशालिन्. -iness, s. उत्साहः, हर्षः, पटुता.

Spring, *s.* वसंतः,-कालः -समयः, सुरभिः, मधुः, कुसुम-समयः-कालः, मधुमासः; 's. of life' प्रथमं वयः, अक्षतं यौवनं, अयातयामं वयः. 2 उत्सः, निर्झरः. स्रोतस् *n.*, वारिप्रवाहः, प्रस्रवणं; 's.-water' नैर्झरं जलं, निर्झरवारि. 3 प्रभवः, उद्भवः, मूलं, उत्पत्तिस्थानं, योनि *f.*; *See* **Origin.** 4 उत्प्लवः, प्लव., प्लुतं-ति *f.*, उत्प्लुतिः, वल्गितं. 5 स्थितिस्थापकत्वविशिष्टः पदार्थः. -*v. i.* उद्भिद् pass.; प्ररुह् 1 P, स्फुट् 6 P, अंकुरयति (D.), *See* **Shoot.** 2 उत्पद् 4 A, प्र-,जन् 4 A, प्र-,सं-उद्-भू 1 P, प्रवृत् 1 A, उद्-इ 2 P, निःसृ 1 P; also by भव, संभव, उद्भव, जात, ज in comp.; 'sprung from a noble family' कुलज, कुलोद्भव, कुलसंभव, &c.; 'sprung from a royal family' राजवंश्य, राजवंशज. 3 परावृत्, परापत् 1 P, उत्पत्. 4 प्लु 1 A, वल्ग् 1 P; 's. up' उत्पत्, उत्प्लु; 's. over' लंघ् 1 A, 10, उत्प्लुत्य अति-इ; 's. upon' सवेगं आपत् 1 P or आक्रम् 1 U, 4 P, सरभसं आस्कंद् 1 P. 5 **Split, Start,** q. v. -*v. t.* उत्था c. (उत्थापयति), प्रबुध् c. 2 उद्-भू c., उत्पद् c., जन् c. 3 **Burst, Split,** q. v.

Springe, *s.* पाशः; *See* **Snare.**

Sprinkle, *v. t.* सिच् 6 P, आ-नि-अव-,° सं-प्र-अभि-उक्ष् 1 P; अवकृ 6 P. -**er,** *s.* सेक्तृ *m.*, सेचकः, प्रोक्षकः. -**ing,** *s.* प्रोक्षणं, आ-अव-सेकः; 's. of' ex. by विरल-*a.*, (विरलतुषारकणाः).

Sprite, *s. See* **Ghost.**

Sprout, *s.* मंजरी. 2 पल्लवः-वं, किस(श)लयः-यं; अंकुरः, प्ररोहः, उद्भिद्-अभिनवोद्भिद्-*m*, उद्भिज्जः. -*v. i.* उद्भिद् pass., प्ररुह् 1 P, स्फुट् 6 P, उत्-फुल्ल् 1 P, विकस् 1 P. -**ed,** *a.* उद्भिन्न, अंकुरित, पल्लवित, स्फुटित. -**ing,** *a.* उद्भिद्-उज्-द, प्ररोहिन्, अंकुरित. -*s.* उद्भेदः; प्ररोहः.

Spruce, *a.* विनीत. विनीतवेश; *See* **Neat.**

Spume,-y, *See* **Froth,-y.**

Spur, *s.* कंटकः. 2 नखः-खं (of a cock). 3 प्रोत्साहनं, उत्तेजनं, प्रचोदनं, उत्साहहेतुः-कारणं; *See* **Incitement, Incentive;** , 'on the s. of the moment' पूर्वं अविचार्य or अनालोच्य, अविचारपूर्वं. -*v. t.* कंटकेन उत्सह् c., पतुद् 6 P. 2 (On) प्रोत्सह् c , प्रचुद् 10; *See* **Prompt.**

Spurious, *a.* कृत्रिम, काल्पित, कपट-कूट-मिथ्या in comp.; *See* **Counterfeit, False.**

Spurn, *v. t.* (Away) लत्ताप्रहारेण प्रत्याक्षिप् 2 P or निः सृ c. or प्रत्यादिश् 6 P. 2 [illegible] अवधीर् 10, तिरस्कृ 8 U, निर्-अव-धू 5, 9 U, निराकृ, धिक्कृ, सावज्ञं प्रत्यादिश्; *See* **Scorn, Contemn.**

Spurt, *s.* हठोद्यमः, महाप्रयत्नः. 2 सवेगः जलोत्क्षेपः. -*v. t.* सवेगं उत्क्षिप् 6 P or उद्वम् 4 U. -*v. i.* सवेगं निःसृ 1 P or निःसृ 1 P.

Sputter, *v.* अंबूकृ 8 U, सनिष्ठीवं वद् 1 P or उच्चर् c. -*s.*,-**ing,** *s.* अंबूकृतं, निष्ठीवनं.

Sputum, *s. See* **Spittle** under **Spit.**

Spy, *s.* चारः, चरः, अप(व)सर्पः, स्पशः, प्रणिधिः, गूढ or गुप्त-चरः or गतिः, गूढ-गुप्त-पुरुषः; पिशुनः, सूचकः, कर्णेजपः, रहस्याख्यायिन् *m.* (slanderous): 'see as a s.' अपसृप् 1 P. (स मया पौरजानपदानपसर्पितुं प्रयुक्तः U. 1); 'the king sees by s. es' चारचक्षुर्महीपालः. -*v. t.* दृश् 1 P, ईक्ष् 1 A; *See* **See.** 2 निरूप् 10. निरीक्ष्, अवेक्ष्, अनुसं-धा 3 U.

Squab, *a.* ह्रस्वस्थूल.

Squabble, *See* **Quarrel.**

Squad, *s.* नवसैन्यदलं.

Squadron, *s.* (सैन्य-) गणः, गुल्मः-ल्मं, दलं, व्यूहः. 2 पोतावली, नौसमूहः.

Squalid, *a.* मलिन, कुत्सित, अमेध्य, अप-निकृष्ट, अधम, जघन्य; *See* **Dirty.**

Squall, *s.* चीत्कारः, चंडरवः, कलकलः, उत्क्रोशः, उच्चनादः-रवः. 2 (Of wind) चंडवातः, प्रभंजनः, प्रकंपनः. -*v. i.* उत्-व्या-क्रुश् 1 P, उच्चैः रु 2 P or घुष् 10; *See* **Scream.**

Squander, *v. t.* अप-व्यय् 10 (-व्ययति), विक्षिप् 6 P, मुधा क्षै c. (क्षपयति) or ह्र 1 P, अमितं व्ययं, अतिव्ययं कृ. -**er,** *s.* अपव्ययकारिन् *m.*, अमितव्ययकारी, विक्षेपिन् *m.* -**ing,** *s.* अपव्ययः, विक्षेपः; अति-अमित-व्ययः.

Square, *s.* (In Arith.) वर्गः, कृति *f.*, द्विघातः; 's. root' वर्गमूलं, पदं; 'the root of the sum of their s. s' तत्कृत्योर्योगपदं; 'take the s. root' पदीकृ, (Li.). 2 (In geometry) वर्गः, समचतुरस्रः, समचतुर्भुजः. 3 चत्वरं, अंगणं; *See* **Courtyard** 's. formed by 4 houses' संजवनं, चतुःशालं. -*v. t.* वर्गीकृ 8 U, वर्गयति (D.), द्विः हन् 2 P or गुणयति (D.). 2 समीकृ, ऋुध् c.; समा-धा 3 U, प्रति-सं-आ-युज् 7 U, 10. -*v. i.* संवद् 1 P, युज्-उपपद् pass.; *See* **Suit.** -*a.* समचतुर्भुज, समचतुरस्र. 2 **Just,** q. v.

Squash, *v. t.* संचूर्ण् 9 P, संपीड् 10, संपिष् 7 P, चूर्ण् 10 -*s.* संमर्दः, संपीडनं, चूर्णनं

Squat, *v. i.* उत्कटुकासनं कृ 8 U, अवसक्थिकासनं कृ; अवनतसक्थि आस् 2 A or उपविश् 6 P. 2 **Cower,** q. v.

Squeak, Squeal, *v. i.* कर्कशं रु 2 P or नद् 1 P, वाश् 4 A. -*s.* कर्कशरवः नादः, वाशितं, चीत्कारः.

Squeamish, *a.* विवमिषु, वमनोन्मुख (खी *f.*). 2 **Fastidious,** q. v. **-ness,** *s.* विवमिषा.

Squeeze, *v. t.* नि-सं-पीड् 10, संमृद् 9 P, निष्पिष् 7 P: (out) निर्गल् c., निष्कुष् 1 P, निर्दुह् 2 U; *See* **Crush, Press. -ing,** *s.* संपीडनं, संमर्दः-र्दनं, निर्गालनं, निष्पेषः, निष्कर्षः.

Squelch, *v. t.* निर्दल् 1 P, विध्वंस् 1 A. **-s** आघातः, प्रहारः.

Squib, *s. See* **Satire.**

Squint, *v. i.* तिर्यक् दृश् 1 P or प्रेक्ष् 1 A, वक्रं वीक्ष्. **-s.** तिर्यक्-वक्र-दृष्टि *f.*; 's.-eyed' वक्रदृष्टि, वलिर, केकर, केदर; तिर्यग्दृष्टि.

Squire, *s.* महाजनः, आर्यः, श्री pr. 2 साहसिकः.

Squirm *v. i. See* **Writhe.**

Squirrel, *s.* काष्ठमार्जारः-बिडालः, वृक्षशायिका, चमरपुच्छः.

Squirt, *s.* धारायंत्रं. **-v. t.** उदस् 4 U, उत्क्षिप् 6 P, बलेन निःसृ c. or निरस्.

Stab, *v. t.* (छुरिकया &c.) व्यध् 4 P, भिद् 7 P, क्षण् 8 P, छुर् 1 P: 's. in the secret' परोक्षे मर्मभेदं कृ 8 U. **-s.** क्षतं. वेधः, खड्गभेदः.

Stable, *a.* स्थिर, निश्चल, अचल, दृढ, स्थावर; *See* **Firm. -s.** मंदुरा, वाजि-अश्व-शाला; (for elephants) वारि, गजबंधनी; (for cattle) गोशाला, गोष्ठ; 's.-keeper' अश्वपालः, मंदुरापालः. **-Stability,** *s.* स्थैर्यं, दृढता, सं-,स्थिति *f.*, स्थायित्वं. प्रतिष्ठा: *See* **Permanence.**

Stack, *s.* राशिः, सं-,चयः, संघः, उत्करः, चिति *f.* **-v. t.** राशीकृ 8 U. समाहृ 1 P. आ-सं-चि 5 U.

Staff, *s.* दंडः, यष्टि *f.*, वेत्रं (cane). लगुडः (wooden). 2 आलंबः-बनं, आधारः, आश्रयः. 3 वर्गः, गणः, अधिकारिगणः &c.; 's. of teachers' शिक्षकवर्गः-समुदायः.

Stag, *s.* हरिणः, मृगः, कुरंगः-गमः, एणः.

Stage, *s.* रंगः,-भूमि *f.*, शाला; नाट्यशाला; नेपथ्यं; 'behind the s.' नेपथ्ये. 2 मंचः-चकः. 3 (On a journey) वसति *f.* (तिस्रो वसतीरुषित्वा R. vii. 33), प्रयाणकं; विश्रामस्थानं, अवस्थानं. 4 पदं, स्थानं, आस्पदं, वृत्ति *f.*, दशा, अवस्था. 5 (State of existence) आश्रमः, (वानप्रस्थाश्रमः); 'last s.' चरमावस्था; 'first s.' उपक्रमः, प्रथमारंभः; 's.-coach' अश्वयानं, पथिकयानं; 's.-manager' सूत्रधारः; 's.-player' रंगोपजीविन् *m.*, नटः, नर्तकः.

Stager, *s.* ज्ञानवृद्धः, वृद्धः.

Stagger, *v. i.* प्रस्खल् 1 P, विचल् 1 P, भ्रम् 1, 4 P, घूर्ण् 1 A, 6 P, दोलायते (D.): समर्थ-सत्वकीर्ति-पराहत् 1 A. 2 विशंक् 1 A. विकृप् 1 A. **-v. t.** विचल् c., भ्रम् c., शंका-विकल्पं-उत्पद् c.

Stagnant, *a.* स्थिर, निश्चल, निष्प्रवाह, निःश्रोत, गति or प्रवाह-हीन or रहित. **-Stagnate,** *v. i.* स्थिरीभू 1 P, ex. by (*a.*) with भू; 'when the stream of knowledge s.s' यदा ज्ञानस्रोतसो प्रतिरोधः भवति, ज्ञानस्रोतोगतिः कुंठिता भवति. **-ion,-Stagnancy,** *s.* अप्रवाहः, निश्चलता, गति-प्रवाह-अभावः, निश्चलता, स्थैर्यं.

Staid, *a.* धीर, ग(गं)भीर, स्थिर; *See* **Serious.**

Stain, *v. t.* (lit. and fig.) दुष् c. (दूषयति), कलंकयति-मलिनयति-आविलयति-कलुषयति (D.), मलिनी-कलुषी-कृ 8 U, लिप् 6 P, लांछ् 1 P, समली-मलीमसी-कृ; 'what is the use of life s. ed by infamy (ignominy)' उपक्रोशमलीमसैः प्राणैः किं (R. ii. 53); 's. ed by blood' रक्तमलिन; 'with s. ed hands' लिप्तहस्त. 2 रंज् c. **-s.** कलंकः, अंकः, दूषणं, लांछनं, चिह्नं, कलुषं, मलं, मालिन्यं. 2 निंदा, उपक्रोशः, वाच्यता, वचनीयं, गर्हा. **-less,** *a.* निष्कलंक, निर्मल, अदूषण, अकलुष, कलंक-लांछन-हीन, निर्दोष, निरवद्य.

Stair, *s.* सोपानं, आरोहणं, पदक *n.*, पंक्तिः-क्ती *f.*; 'flight of s. s,' 's.-case,' 's.s' सोपानपथः-मार्गः-पद्धति *f.*,-परंपरा-पद्धती-पंक्ति *f.*, निश्रेणी, अधिरोहिणी.

Stake, *s.* ग्लहः, पणः 2 कीलः, शंकुः, शूलः-लं; स्थाणुः, स्थूणा, शलाका. 3 संशयः, संदेहः; 'his life was at s.' संशयस्थं जीवितं तस्य, संशयितजीवित आसीत्, जीवितं संशयदोलाधिरूढं. **-v. t.** पण् 1 A, (with gen. of thing staked); शतस्य पणते 's. s a hundred'. 2 शूलेन-कीलेन व्यध् 4 P or बंध् 9 P, कील् 10.

Stale, *a.* यातयाम, परि-,उषित, पर्युषित, निःसार, नीरस, असत्व; दुष्ट (जलं). 2 जीर्ण, पुराण, उच्छिष्ट. **-v. i.** मिह् 1 P, मूत्र् 10.

Stalk, *s.* कांडः-डं, नालः-लं-ली, वृंतं, इषि, प्रसव-शस्य-बंधनं. 2 साटोपगति *f.*, धीरोद्धता गतिः. **-v. i.** साटोपं परिक्रम् 1 U, 4 P, उद्धतं-सगर्वं-चल् or गम् 1 P, धीरोद्धतं गम्; 's. ing-horse' **Pretext,** q. v.

Stall, *s.* पण्यवीथिका, पण्यवेदि. आपणः, विपणि *f.*; *See* **Shop.** 2 शाला, स्थानं; (for horses) मंदुरा, अश्वस्थानं; (for cattle) गोष्ठं, गो-शाला-स्थानं.

Stallion, *s.* बीजाश्वः सवृषणः अश्वः.

Stalwart, *a.* दृढांग, प्रबल, 2 वीर, धृतिमत्.

Stamen, *s.* केसरः, किंजल्कः.

Stamina, *s.* (fig.) सारः, सत्त्वं, तेजस् *n.*, बलसाधनं-हेतुः.

Stammer, *v. i.* स्खल् 1 P, असमंजसं जल्प् 1 P, स्खलद्वाक्येन-अस्पष्टवर्णैः-अस्फुटस्वरेण-गद्गदवाचा-वद् 1 P, अस्पष्टं-अस्फुटं-वच् 2 P. **-er,** *s.* अव्यक्त-अस्पष्ट-वादिन् *m.*, स्खलत्-गद्गद-वादी, स्खलितस्वरः. **-ing,** *s.* स्खलनं, अस्पष्ट-अव्यक्त-भाषणं.

Stamp, *s.* मुद्रा, मुद्रिका, मुद्रायंत्रं. **2** मुद्रा, चिह्नं, अंकः, न्यासः, पदं. **3** पादप्रहारः -आघातः-विष्टंभः. **4** स्व-,रूपं, आकारः, आकृति *f.*, प्रकृति *f.*, संस्कारः; 'of the common s.' सामान्यप्रकृति, प्राकृत; 'of high s.' महाप्रभाव, महानुभाव; 'of the same s.' समानरूप, तुल्य-स्वभाव-प्रकृति. **-***v.* पादेन-पादतलेन-प्रहृ 1 P or आ-अभि-हन् 2 U, पादप्रहारं कृ 8 U. **2** अंक् 10, मुद्रयति-चिह्नयति- ((D.), लांछ् 1 P; 's.-ed with infamy' दुष्कीर्तिचिह्नित, उपक्रोशमलीमस, अपयशोंकित. **3** क्लृप् c., रच् 10, संवि-धा 3 U. **4** पादतलेन मृद् 9 P or चूर्ण् 10 or पिष् 7 P. **-ed,** *a.* अंकित, लांछित, समुद्र, कृतमुद्र, मुद्रांकित.

Stampede, *s.* ससंभ्रमं पलायनं.

Stanch, *a.* दृढ, स्थिर, धीर, अचल; 'a s. adherent' बद्धानुरागः सहायः, दृढपक्ष्यः; *See* **Firm.** **-***v. t.* प्रवाहं-प्रस्रावं स्तंभ् 9 P or रुध् 7 U, शुष् c. **-***v. i.* शुष् 4 P, स्तब्धप्रवाह *a.* भू 1 P.

Stanchion, *s.* क्षुद्रस्तंभः-स्थाणुः.

Stand, *v. i.* स्था 1 P, पद्भ्यां स्था. **2** वृत् 1 A, विद् 4 A, अव-स्था 1 A; *See* **Remain.** **3** भू 1 P, अस् 2 P, वृत्. **4** निवृत्, विरम् 1 P, स्तंभ् pass., स्थिर-रुद्धगति-कुंठित- *a.* भू; 'this will remain a s.-ing stigma (on me)' वचनीयमिदं व्यवस्थितं (K. IV. 21); 'this argument will not s. long' इयं युक्तिर्न चिरं स्थास्यति, आचिरात् खंडयिष्यते. **-***v. t.* सह् 1 A, मृष् 4 P, 10 *See* **Bear;** 'to s. the test' निकषपरीक्षां तॄ 1 P, निकष परीक्ष् pass. **2** उप-नि-रुध् 7 U; प्रति-वि-रुध्. **-against,** प्रत्यव-स्था, बाध् 1 A, विरुध् *See* **Oppose.** **-by,-near,** साहाय्यं कृ, संरक्ष् 1 P, परि-,श्रि 1 A. उपकृ; अनुग्रह्. **2** स्था, अव-स्था; अनुरुध् 4 A, अनुवृत्; 's. by your lord's orders' शासने तिष्ठ भर्तुः (V. 5); *See* **Obey.** **-for,** स्थाने-भूमौ स्था or वृत्. **2** पदं आप् desid. (ईप्सति). **-off,** अपसृ 1 P, दूरतः स्था. **-on,** आ-अव-लंब् 1 A, आ-स्था (A). आश्रि 1 U. **-out,** प्रलंब्, उद्गम् 1 P: *See* **Project.** **2 Persist,** q. v **-over,** स्थागित् pass. **2** अधि-ष्ठा, अध्यास् 2 A; 'his name s. s over all' स सर्वेषां मूर्ध्नि तिष्ठति. **-to,** संवद् 1 P; 'does not s. to reason' सयुक्तिकं-सोपपत्तिकं न भाति. **-up,** उत्था. **-***s.* आधारः, भाजनं, पात्रं, उपष्टंभः, आश्रयः; 'ink-s.' मसीपात्रं-धानी; 's. of a lamp' दीपाधारः-वृक्षः. **2** मंचः. **3** अव-,स्थानं, पदं, स्थिति *f.*, अव-,स्तंभः, प्रतिरोधः-स्तंभः, कुंठनं, 'come to a s.' स्तब्ध-शांत- *a.* भू; 'bring to a s.' स्तंभ् 9 P or c., गतिं रुध् or वृ c.: at a s.-still' कुंठित, प्रतिहत-रुद्ध-गति; 'make a s. against' प्रतिबंध् 9 P, प्रत्यव-स्था (A), प्रति-विरुध्. **-ing,** *s.* अव-,स्थितिः, अवस्थानं, स्थायित्वं; 'of long s.' चिरस्थायिन्, दीर्घकालीन, पुराण; *See* **Old.** **2** स्थानं, पदं, आस्पदं, पदवी, प्रतिष्ठा; 'high s.' उच्चपदं, महती प्रतिष्ठा. 'who has obtained a s.' लब्धप्रतिष्ठः **-***a.* सनातन, चिर-नित्य-स्थायिन्; *See* **Lasting.** **2** स्थित, उत्थित, दंडवत् स्थित. **3** स्थ, स्थायिन्, वर्तिन्, अव-,स्थित in comp.; 'with the hair s. on their end' पुलकित, रोमांचित, कंटकित.

Standard, *s.* ध्वजः, पताका, केतुः, केतनं, वैजयंती; 's.-bearer' ध्वजिन्, पताकिन्. **2** मानं, प्र-परि-°, सूत्रं, विधिः, नियमः; 'a s. person' प्रमाणपुरुषः, प्रमाणं; 's. authors' प्रमाणभूताः (विशिष्टाः) ग्रंथकृतः.

Stanza, *s.* श्लोकः.

Staple, *a.* प्रधान, मुख्य, विशिष्ट. **-***s.* **Market,** q. v. **2** लोहपुटः.

Star, *s.* तारा, तारका, नक्षत्रं, ज्योतिस् *n.*, उडुः, भं, ऋक्षं; 'the s. s collectively' उडुगणः, भगणः; 'shooting s.' नक्षत्रपतनं, उल्का; 's. under which one is born' जन्मनक्षत्रं; 's.-light' ताराप्रकाश, तारकित, (*s.*) ताराप्रकाशः. **-***v. t.* तारासनाथ- *a.* कृ 8 U, तारकयति (D.); 'the breast s. ed with drops of tears' अश्रुबिंदुतारकितपयोधरा; 'the s.-red heaven' तारासनाथं-तारकितं-नभः. **-ry,** *a.* तारासंकुल-मय (यी *f.*)-आकीर्ण-सनाथ, तारकित. **2** तारानिभ, तारा in comp.; 's. firmament' नभोमंडलं, नक्षत्रमंडलं.

Starboard, *s.* नौदक्षिणपार्श्वः.

Starch, *s.* मंडः-डं. **-***v. t.* मंडयति (D.), मंडेन लिप् 6 P.

Stare, *v. i.* सूक्ष्मं-बद्धलक्ष्यं-स्थिरदृष्ट्या-अनिमिषलोचनाभ्यां-प्रेक्ष् 1 A or दृश् 1 P or आलोक् 1 A, 10, अनन्यदृष्ट्या निरीक्ष्; स्निग्धं निर्वर्ण् 10. **-***s.* स्थिरदृष्टि *f.*, बद्ध-अनिमिष-दृष्टिः, अनन्यदृष्टिः. **-ing,** *a.* बद्ध-स्थिर, अनन्य-अनिमिष-दृष्टि, बद्धलक्ष्य, विवृत-उत्फुल्ल-नयन-लोचन &c., उन्मीलिताक्ष.

Stark, *a.* समग्र, पूर्ण, केवल, अत्यंत, अशेष. **2** रूक्ष, विषम. **-***adv.* केवलं, अत्यंतं.

Start, *v. i.* प्र-स्था 1 A, प्र-या 2 P, प्र-,चल् 1 P यात्राभिमुखं प्रवृत् 1 A 's. on a journey' (Mal. 6). **2** स्फुर् 6 P, सहसा

कंप् 1 A or स्पंद् 1 A; 's. back' ससाध्वसं परावृत् or अपसृ 1 P, सचकितं व्यपसृ, चकित-a. भू; संत्रस्त-भयचकित- a. भू; 's. aside' स्वस्थानात् विचल् or भ्रंश् 1 A, 4 P or च्यु 1 A; अभिजागतयः शब्दं सहंते (S. 1) 'not s. ing aside &c.;' 's. up' सहसा उत्था; (in sleep) सहसा अवबुध् 4 A.; (an idea) सहसा उद्भू or उत्पद् 4 A. –v. t. प्रवृत् c., प्र-स्तु c., संचल् c., प्रचर् c. 2 उद्विज् c., संत्रस् c., चकित-a. कृ 8 U, उत्था c. (उत्थापयति), भी c.; अकस्मात् त्रस् c. or कंप् c. 3 Propose, q. v. –s. प्रस्थानं, प्रस्थानारंभः. 2 कंपः-पनं, स्फुरणं, साध्वसोत्कंपः, सहसाकर्षः, आकास्मिकप्रकंपः; चकितं; 'gave a sudden s.' (सहसा) ससाध्वसं चकितो बभूव; 'with a s.' चकितं, सचकितं. 2 प्रवर्तनं, आरंभः, प्रचारः; 'to get or have the s. of' पूर्व (with abl.) प्र-स्था or प्रारभ् 1 A; 'by s. s' सातत्यं विना, प्लुतैरिव, आकास्मिकयत्नैः.

Startle, v. *See* **Start**; 's. ing news' उद्वेगकरी वार्ता; in a very s. ed manner' चकितचकितं.

Starve, v. i. क्षुधया पीड् or अर्द् pass., आहाराभावात् मृ 6 A or अव-,सद् 1 P or नश् 4 P, क्षुधया अवसद्; (oneself) आहारं-अशनं-त्यज् 1 P, प्रायोपवेशनं कृ 8 U; 'likely to s.' आसन्नमृत्युरिव, अनशनेन मुमूर्षुरिव; (fig.) अव-,सद्. –v. t. अनशनेन मृ c. or नश् c.; 'be sure, I shall s. myself (to death)' मया प्रायोपवेशनं कृतं विद्धि (P IV. 1). –ation, s. अनशनं, अनाहारः, आहाराभावः, क्षुधावसादः, क्षुत्क्षामता. –ed, –ing, a. क्षुधापीडित-अर्दित-आर्त, क्षुधावसन्न, निराहार, निरन्न.

State, s. अवस्था, दशा, भावः, स्थिति f., वृत्ति f., गति f.; त्वं-ता affixed. 2 राज्यं, राष्ट्रं, राजन् in comp.; 's. affairs' राजकार्याणि; 's.-servant' राजसेवकः. 3 ऐश्वर्यं, आडंबरः, आटोपः, प्रतापः, वैभवं, विभूति f., श्रीः, गौरवं. –v. t. कथ् 10, आचक्ष् 2 A, वच् 2 P, वद् 1 P, नि-आ-विद् c., निर्दिश् 6 P, वि-ज्ञा c. (ज्ञापयति), वर्ण् 10, उपन्यस् 4 U; *See* **Tell**, *Say*. –ed, a. कथित, उक्त, निर्दिष्ट, वर्णित, &c.; 'as above s.' यथानिर्दिष्ट. 2 नियत, व्यवस्थित. –ly, a. सप्रताप, सश्रीक, सवैभव, उज्ज्वल; *See* **Majestic**; **Grand**. 2 साटोप, उद्धत, सखेल; 's. in gait' साटोपगामिन्, खेलगति-गामिन्, हंसगामिन्. –adv. साटोपं, उद्धतं, सखेलं, सलीलं, सप्रतापं. –ment, s. कथनं, आ-नि-वेदनं, उक्ति f., वचनं, उपन्यासः, निर्देशः, विज्ञापना; 'clearness of s.' उपन्यासशुद्धिः. –*Statesman*, s. नीतिज्ञः-विद् m. -विशारदः, राजकार्यकुशलः-धुरंधरः, राजनीतिनिपुणः. –ship, s. नीतिज्ञता, नीति f.

Station, s. स्थानं, अव-,स्थिति f., आस्पदं, स्थलं, पदं, अवस्थानं. 2 दशा, पदं, अवस्था, वृत्ति f, पदवि-वी f.; 'high s.' उन्नतपदं, परमस्थानं, उन्नतावस्था; 's. of life' जाति f. 3 अधिकारः, नियोगः, पदं, पदवि-वी. 4 निवेशः. –v. t. स्था c. (स्थापयति), अव-सं-प्रति-°, निविश् c.; 's. in any post' पदे-अधिकारे-नियुज् 7 A, 10. –ary, a. स्थिर, अचल, निश्चल, अचर, स्थावर; अजंगम. 2 अवर्धिष्णु, अवर्धमान.

Stationer, s. लेखनसाधनविक्रयिन् m. –y, s. लेख-लिपि-साधनं-सज्जा-सामग्री.

Statue, s. प्रतिमा, प्रतिकृति f., मूर्ति f.; *See* **Image**. –*Statuary*, s. कारः in comp. with (s.), तक्षकः. 2 मूर्तिविधानं-करणं.

Stature, s. प्रमाणं, परिमाणं, उच्चता, मूर्ति f., आकृति f., आकारः; 'of low s.' अल्पप्रमाण; 'of dwarfish s.' वामनाकृति, खर्व, ह्रस्व; 'short in s.' ह्रस्व-अल्प-मूर्ति.

Status, s. स्थिति f., पदवी.

Statute, s. विधिः, नियमः, व्यवस्था; *See* **Law**, **Rule**. –*Statutory*, a. विधिप्रोक्त, व्यवस्थाकल्पित, नियत.

Stave, s. काष्ठखंडः-डं, फलकः-कं. –v. t. स्फुट् c., छिद्रयति (D.).

Stay, v. i. वस् 1 P, स्था 1 P, वृत् 1 A, अध्यास् 2 A; *See* **Dwell**. 2 विरम् 1 P; अलं with instr. or gerund. –v. t. स्तंभ् 9 P, प्रतिबंध् 9 P, उप-नि-रुध् 7 U, विलंब् c., नि-प्रति-वृ c.; नि-प्रति-षिध् 1 P; 's. one's progress' मार्गं निरुध् (Mr. 5.). 2 आ-अव-लंब् 1 A, आश्रि 1 U, आधृ 10, अव-उप-स्तंभ्; *See* **Prop**. –s., –ing, s. नि-,वारणं, अवस्थानं, अव-,स्थिति f. 2 आलंबः, आधारः, आश्रयः, उपघ्नः, उप-अव-स्तंभः. 3 प्रतिबंधः, निरोधः, गतिरोधः, प्रतिबंधः. –*Stays*, s. अंगिका, चोलः लं, कूर्पासकः.

Stead, s. स्थानं, भूमि f.; *See* **Instead** (of).

Steadfast, a. स्थिर, दृढ, सतत, अचल; निश्चल, धीर, स्थिरबुद्धि-वृत्ति, अचंचलवृत्ति; 's. in friendship' दृढसौहृद. –ly, adv. दृढं, स्थिरं. –ness, s. स्थैर्यं, धैर्यं, धृति f.

Steady, a. स्थिर, दृढ, अचल, निश्चल, धीर, अस्खलित, धृतिमत्; सतत, अविश्रांत, अविरत; अविरतोद्योग, सततोद्यमिन्; 'of s. action' स्थिरकर्मा; 's. in resolution' स्थिर-दृढ-निश्चय-संकल्प. 2 अनुद्विग्न, अक्षुब्ध, अनाकुल, प्रशांत. –v. t. स्थिरीकृ 8 U, दृढयति (D.), दृढीकृ, व्यव-स्था c. (स्थापयति). –ily, adv. स्थिरं, दृढं, धीरं, अनवरत, अविरतं, नित्यं, सदा, अविश्रांतं. –iness, s. स्थैर्यं, धैर्यं, अचापल्यं,

नित्यता, सातत्यं, अविच्छेदः, अविरति *f.*; 's. of conduct' अव्यभिचारः, आचारमर्यादा.

Steal, *v. t.* चुर् 10, मुष् 9 P, अपहृ 1 P, स्तेन् 10. –*v. i.* चुर्, स्तेयं वि-धा 3 U. 2 (Away) अलक्षित-निभृतं-गम् 1 P or अप-क्रम् 1 U, 4 P or अपसृ 1 P; निःशब्दं चल् 1 P; 'the night, the quarters of which (gradually) stole away' अविदितगतयामा रात्रिः (U. 1); 's. over, upon' अलक्षितं समाक्रम् or अभिभू or ग्रस् 1 A; 'sleep gently stole upon my eyes' शनैर्निद्रा निमीलितलोचनं मामकार्षीत्. **–er,** *s.* अपहर्तृ *m.*, अपहारकः, स्तेनः, स्तेयकृत्, चो(चौ)रः, मोषकः, तस्करः, हारी in comp.; 's. of hearts' हृदयचौरः. **–ing,** *s.* स्तेयं, चौरकर्मन् *n.*, स्तैन्यं, चौर्यं, मोषः, अपहारः. **–th,** *s.* अपहारः &c. 2 छलं, गूढं कर्म, चोरिका, निह्नवः, निभृत-प्रच्छन्न-कर्म; 'marriage by s.' चोरिकाविवाहः. **–thily,** 'by s.' *adv.* छलेन, निभृतं, प्रच्छन्नं, अलक्षितं, अप्रकाशं, रहसि. **–thy,** *a.* निभृत, प्रच्छन्न, गुप्त, गूढ, रहस्य, अलक्षित, अप्रकाश, अव्यक्त.

Steam, *s.* बाष्पः; 's. boat' 'steamer' अग्निनौका, बाष्पीयनौः. –*v. i.* बाष्पायते (D.), बाष्पं उत्-सृज् or उत्क्षिप् 6 P or उद्-गृ 6 P. –*v. t.* बाष्पेण व्याप् *c.*, स्विद् *c.*

Steed, *s.* अश्वः, तुरगः, वाजिन् *m.*; *See* **Horse.**

Steel, *s.* खिश्रायस, सारलोहं, पिंडायसं, तीक्ष्णायसं, शस्त्रकं. 2 शस्त्रं, शस्त्रकं; 's.-yard' तुलादंडः, मापनदंडः –*a.* तीक्ष्णायस (सी *f.*). –*v. t.* काठिनीकृ 8 U, दृढी-निर्दयी-कृ.

Steep, *a.* दुरारोह, उत्सर्पिन्, पातुक, प्रवण, अतट. –*s.* प्रपातः भृगुः, अतटः –*v. t.* नि-, मस्ज् *c.* (मज्जयति), स्ना *c.* (स्न-स्ना-पयति), जलेन आप्लु *c.* or सिच् 6 P. 2 सं-धा 3 U, वास् 10, धू *c.*; 's.ing indigo' नीली-संधानं-पाचनं; 's. ed in perfumes' वासित, भावित.

Steeple, *s.* शिखरं शृंगं, (of a palace &c.)

Steer, *s.* वत्सतरः, दम्यः. –*v. t.* चल् *c.*, वह् *c.*, मार्गं उपदिश् 6 P (with gen.); नी 1 P, मार्गं नि-श्चि 5 U or निर्णी; 's. one's course' स्वमार्ग-कर्तव्यं-निर्णी; 'he who s. s the vessel of state' (निर्वाह) राज्यधुर्वहः, भुवनराज्यभारनौकर्णधारः (Ka. 56). **–er, –Steersman,** *s.* कर्णधारः-ग्राहः, कर्णिन् *m.*, नाविकः.

Stellar, *a.* तारा in comp.; *See* **Starry.** **–Stellate, –ed,** *a.* तारोपम.

Stem, *s.* काण्डं, वृंतं, प्रसवबंधनं. 2 प्र-कांडः-डं; स्तंभः, नालं-लः. –*v. t.* प्रतिबंध् 9 P, प्रति-वि-रुध् 7 U, प्रति-ष्टंभ् 9 P, प्रत्यव-स्था 1 A, प्रतिकूलयति-प्रतीपयति (D.); *See* **Oppose.**

Stench, *s.* पूति *f.*, पूतिगंधः; दुर्गंधः.

Stentorian, *a.* अतितार, अत्युच्च; उच्चस्वन.

Step, *s.* पदं, पद् or पाद-न्यासः or विक्षेपः, क्रमः, पद-चरण-पातः, विक्रमः (as in त्रिविक्रमः); 'Vishnu took 3 s. s' विष्णुस्त्रीणि पदानि विचक्रमे. 2 पदं, क्रमः, (distance also); पर्यायः, परिपाटी; 'at every s.', 's. by s.' प्रति-अनु-पदं, पदे पदे, पदात्पदं, क्रमशः, पदशः; 'by s. s' क्रमशः, शनैः शनैः, क्रमेण; 'the first s.' प्रथमारंभः, उपक्रमः, प्रथमचरणः. 3 (Of a ladder) भंगि *f.*, सोपानं, आरोहणं; 'flight of s. s' अधिरोहिणी; *See* **Ladder, Staircase.** 4 उपायः, प्रतिपत्ति *f.*, क्रिया; 'वयस्य कात्र प्रतिपत्तिः (Mal. 3); 'not knowing what s. s to take' प्रतिपत्तिमूढः, विषादलुप्तप्रतिपत्ति (R. III. 40); 's.-brother' वैमात्रः-त्रेयः, विमातृजः, अन्योदर्यः; 's.-child' अन्योदर्यं अपत्यं 's.-daughter' सपत्नीसुता; 's.-father' मातुः पतिः; 's. mother' विमातृ *f.*, सपत्नीमाता; 's.-sister' वैमात्री-त्रेयी, विमातृजा, अन्योदर्या; 's.-son' सपत्नीसुतः. –*v.* पादं विन्यस् 4 U or निक्षिप् 6 P, पादन्यासं-पदविक्षेपं कृ 8 U. 's.ing over his body' तच्छरीरे पादन्यासं कृत्वा. 2 क्रमशः चल् 1 P or गम् 1 P; (over) आक्रम् 1 U, 4 P, व्याप् 5 P 'as much space as I can s. 'over in three steps' यावतीं भूमिं त्रिपदेनाहं व्याप्नुयां-आक्रमेयं-तावतीं; 's. in between' अंतरा आगम् or पत् 1 P; 's. towards' प्रतिपद् 4 A. **–ping,** *s.* पादन्यासः &c.; 's-stone' सोपानशिला-प्रस्तरः.

Stereotyped, *a.* स्थिर, अपरिवर्तनीय, पूर्वसंकल्पित.

Sterile, *a.* वंध्य, अफल, निष्फल. **–ity,** वंध्यता, निष्फलत्वं.

Sterling, *a.* यथार्थ, परमार्थ, वास्तविक (की *f.*); अकृत्रिम, सारभूत

Stern, *s.* पृष्ठभागः. –*a.* निष्ठुर, रूक्ष, दारुण, परुष, कठिन, कठोर, उग्र; निर्दय, क्रूर; 'in a decisive and s. tone' परिच्छेदनिष्ठुर; 'of s. stuff' अभेद्यसार. **–ly,** *adv.* निष्ठुरं, कठोरं, दारुणं, उग्रं. **–ness,** *s.* नैष्ठुर्यं, कठोरता, पारुष्यं.

Sternum, *s.* उरोस्थि *n.*

Sternutation, *s.* *See* **Sneeze.** **–Sternutatory,** *s.* नस्यं.

Stertorous, *a.* घर्घरायमाण.

Stethoscope, *s.* हृत्परीक्षणयंत्रं, हृत्स्पन्दश्रावणीनलिका.

Stew, *v.t.* मंदं पच् 1 P. –*s.* खिंता, मनस्तापः.

Steward, *s.* परिचारकः. 2 अर्थाधिकारिन् *m.*, कार्याधीशः. **-ship**, *s.* कार्याधीशत्वं.

Stibium, *s.* सौवीरं, कापोतं, स्रोतोंजनं, यामुनं.

Stick, *s.* दंडः, यष्टि *f.*; वेत्रं, वेत्रयष्टिः (cane); काष्ठं, काष्ठखंडः, लगुडः. **-v. i.** सं-लग् 1 P, संश्लिष् 4 P, संज् pass., आ-सं-अनु-°, आसञ्ज् 1 P, अनुबंध् 9 P, संसक्ती-संलग्नी-भू 1 P. 2 मस्ज् 6 P, निरुध्-स्तंभ् pass.; 'the wheels stuck fast into the mire' पंके गाढं निरुद्धानि चक्राणि. 3 विकल्प् 1 A, विशंक् 1 A; *See* **Doubt**; 's out' प्रलंब् 1 A; *See* **Project**. **-v. t.** निविश् c., अनुबंध्, आ-सं-संज् c. संलग्नीकृ 8 U. 2 मस्ज् c. **-y**, *a.* स्निग्ध, चिक्कण, श्यान, सांद्र, संलग्नशील.

Stickle, *v. i.* पक्षं ग्रह् 9 U. 2 **Contend**, q. v.

Stiff, *a.* कठिन, संहत; दृढ, घन, अनम्र, अशिथिल, स्तब्ध. 2 परुष, रूक्ष, कर्कश. 3 अनुगम, दुर्बोध, दुर्ज्ञेय, गहन. 's.-hearted, -necked' प्रतिनिविष्ट, स्तब्ध, दृढनिश्चय. **-en**, *v. t.* कठिनीकृ 8 U, घनीकृ, स्तंभ् 9 P or c. **-v. i.** कठिनीभू 1 P; 'remain with your body s. ed' स्तंभितगात्रस्तिष्ठ. **-ly**, *adv.* दृढं, कठिनं. **-ness**, *s.* काठिन्यं, दृढता, &c.

Stifle, *v. t.* श्वासं नि-,रुध् 7 U, श्वासरोधं कृ. 2 स्तंभ् 9 P or c., निग्रह् 9 P, नियम् 1 P, नियंत्र् 10; *See* **Choke, Suppress**; 'with s. ed words' स्तंभितवाक्.

Stigma, *s.* कलंकः, अंकः, लांछनं, दूषणं. **-tize**, *v. t.* निंद् 1 P परिवद् 1 A, दुष् c. (दूषयति); कलंकयति (D.), अपकीर्त्या अंकृ 10; *See* **Stain**.

Stile, *s.* सोपानमार्गः-पद्धति *f.*

Stiletto, *s.* *See* **Dagger**

Still, *s.* अधोयंत्रं, बकयंत्रं, मंधानपात्रं. **-a.** निःशब्द, नीरव, मूक; *See* **Silent**. 2 निष्कंप, निश्चल, अचल, स्थिर, निश्चेष्ट 3 प्र-उप-शांत, स्तिमित; निर्वात, अक्षुब्ध; *See* **Quiet**; 'heart, be s.' हृदय मा उत्ताम्य (S. 1); 'in the s. midnight' स्तिमितेऽर्धरात्रे; 'to be s.' प्र-उप-शम् 4 P; 's. born' मृतजात, 'a s.-born child' मृतगर्भः, मृतजातः. **-adv.** तथापि. 2 अद्यापि; अद्य यावत्. 3 सदा, सर्वदा. 4 शांतं, तूष्णीं, निःशब्दं. **-v. t.** शम् c. (शमयति), प्र-उप-°, निःशब्दीकृ 8 U. 2 **Stop**, q. v. **-ness**, *s.* निःशब्दता, निश्चलता, शांतता, अक्षोभः.

Stilt, *s.* पादयष्टि

Stimulate, *v. t.* उत्तिज् c., प्रोत्सह् c., प्रचुद् 10, प्रवृत् c., प्रवध् c., उद्दीप् c., (शक्ति-तेजः-) वृध् c. **-ing, -Stimulant**, *s.* उद्दीपक-न, उत्तेजक, प्ररोचक, तेजोवर्धिन्, प्रवर्तक, प्रोत्साहक **-s.** उद्दीपनं-कं, प्र-,रोचनं, जीवनीयं, उत्तेजकं, प्रवर्तकं &c. **-ion**, *s.* प्र-उद्-दीपनं, प्रोत्साहः-हनं. **-Stimulus**, *s.* उद्दीपनं, प्रोत्साहः-हनं, प्रचोदनं, उत्तेजनं, &c.; 'give s. to' वृध् c. &c.

Sting, *v. t.* दंश् 1 P. 2 अत्यंतं पीड् 10 or व्यथ् c. (व्यथयति), मर्माणि भिद्-छिद् 7 P or स्पृश् 6 P. **-s.** दंशः; दंशचंचु *f.*, कंटकः, शंकुः, (of a scorpion) अलं. 2 मर्मन् *n.*, रसः. **-ing**, *a.* कटु, दंशक, मर्मस्पृश्, अरुंतुद.

Stingy, *a.* कृपण, बद्धमुष्टि, दानविरक्त, अमुक्तहस्त, क्षुद्र, कदर्य. **-ily**, *adv.* कृपणं, बद्धमुष्ट्या. **-iness**, *s.* कार्पण्यं.

Stink, *s.* पूति *f.*-गंधः, दुर्गंधः. **-v. i.** Ex. by 's. ing' with भू. **-ing**, *a* पूतिगंधि दुर्गंध, कुत्सितगंध, पूति

Stint, *v. t.* नियम् 1 P, निबंध् 9 P, निग्रह् 9 P, संह् 1 P, परि-मा 3 A, 2 P, परिच्छिद् 7 P. **-s.** परिमाणं, परिमिति *f.*, नियमः-मनं, इयत्ता. मर्यादा; *See* **Limit**.

Stipend, *s.* वेतनं, वृत्ति *f.*, वर्तनं, भृति *f.* **-Stipendiary**, *s.* वृत्ति-वेतन-भुज् *m.*, वृत्तिग्राहिन् *m.*, वैतनिकः.

Stipulate, *v. i.* समयं-संविदं-कृ 8 U, नियम् 1 P; प्रतिपद् 4 A, परि-,पण् 1 A, प्रतिज्ञा 9 A, अभ्युपगम् 1 P, -इ 2 P. **-ed**, *a.* नियत, नैयमिक- सामयिक-(की *f.*), प्रतिज्ञात, संकेतित, निरूपित, निर्दिष्ट. **-ion**, *s.* समयः; संविद् *f.*, अभिसंधिः, नियमः, पणः. संकेतः, प्रतिज्ञा.

Stir, *v. t.* चल् c., सं-वि-°; *See* **Move**; 'when the fuel is s. ed, the fire blazes up' ज्वलति चलितेंधनोऽग्निः (S. 6). 2 आ-वि-लुड् c, क्षुभ् c, (of water); मंथ् 9 P or c., आ-धू 5, 9 U; (up) सं-, क्षुभ् c., उत्तिज् c., प्रकुप् c.; उद्दीप् c., प्रवृत् c., प्रणुद् c.; *See* **Excite, Prompt**. **-v. i.** क्षुभ् 4 P, 1 A, चल् 1 P, उद्विग्न-संक्षुब्ध-*a.* भू 1 P. **-s.** संक्षोभः, संभ्रमः, चलनं, धूननं, विप्लवः, तुमुलं. **-ring**, *a.* प्रक्षोभिन्, प्रकोपक, उद्दीपक.

Stirrup, *s.* पादग्रहणी-धारणी.

Stitch, *v.t.* सिव् 4 P; *See* **Sew**; संश्लिष् c. **-s.** सूचः, सूचिमार्गः-अंकः. 2 शूलः-लं, 'a s. in time saves nine' स्वल्पोऽपि कालकृतो यत्नः महांतं उत्तरकरणीयं यत्नं व्यावर्तयति. **-ing**, *s.* सी(से)वनं, स्यूति *f.*

Stock, *s.* मूलं, मूलधनं, परिपणः; नीवि-वी *f.*; 'common s.' गणद्रव्यं. 2 स्तंबः, कांडः, स्कंधः, वृंत *m.* *f.* 3 संचयः, राशिः, संभारः, सामग्री; 's. in cattle' गोधनं, पशुसंपत्ति *f.* 4 मूलं, प्रकृति *f.*, वंशः, कुलं, अन्वयः. 5

प-,कांड:-डं, स्कंध:. 6 स्तंभ:, स्थाणु:. 7 (S.s) निगड:, हडि:; 's.-dove' कपोत:; *See* **Dove;** 's.-still' स्थिर, स्थाणुरिव अचल. -*v. t.* सं-भृ 1, 3 U, संचि 5 U, समाहृ 1 P, राशीकृ 8 U, उपकल्प् c., परि-,पूर् 10. -*a.* मूल in comp., प्रधान, विशिष्ट; 's. instance' मूर्धाभिषिक्तमुदाहरणं. -**Stockade,** *s.* स्तंभपंक्ति *f.*, शंकुवरणं.

Stocking, *s.* चरणच्छद:, पादावरणं, पादत्राणं.

Stodgy, *a.* मंद, जड. 2 नीरस. 3 दुष्पच्.

Stoic,-al, *a.* नि:स्पृह, जितेंद्रिय, नि:संग, समबुद्धि-चित्त, सुखदु:खानधीन, समसुखदु:ख, इंद्रियाभावश. **-ally,** *adv* औदासीन्येन, नि:संगं, वीतस्पृहं. **-ism,** *s.* नि:स्पृहता, औदासीन्यं, आत्मसंयम:, इंद्रियजय:, सुखदु:खसमता.

Stoke, *v. t.* ज्वल् c

Stolid, *a.* *See* **Stupid.**

Stomach, *s.* जठर:-रं, पक्काशय:, कोष्ठ:, अन्नाशय:, आमाशय:; उदरं, पिचं(चिं)ड:. 2 रुचि *f.*, ex. by **Like,** q. v. 3 औद्धत्यं, दर्प:; *See* **Haughtiness.** -*v. t* वि-,सह् 1 A, मृष् 4 P, 10. **-ic,** *a.* अग्निदीपन-वर्धन (नी *f.*), उत्तेजक, अग्निद, दीपक, रुचक, पाचक. 2 जाठर (री *f.*). -*s.* दीपनं, रुचकं, अग्निवर्धनं.

Stone, *s.* शिला, पाषाण:, अश्मन् *m.*, प्रस्तर:, उपल:, ग्रावन् *m.*, दृषद् *f.*, शर्करा. 2 (Of fruits) अस्थि *n.*, अष्ठि *f.*, अष्ठीला. 3 (In the bladder) अश्मरी, मूत्रकृच्छ्रं. 4 **Testicle,** q. v. 's.-blind' मंदांध; 's.-cutter' औपलिक:, आश्मिक:, पाषाणदारक:; 's.-hearted' पाषाणहृदय, अश्महृदय, निर्दय, कठोर; 's.-horse' बीजाश्व:; 's.-pit' 's.-quarry' प्रस्तरखनि *f.*-आकर:. -*a.* **Stony,** q. v. -*v. t.* लोष्टघातं-उपलै:-हन् 2 P or व्या-पद् c. **-y,** *a.* उपलसंकुल-बहुल-आकीर्ण. 2 औपल (ली *f.*), शिला-प्रस्तर-मय (यी *f.*), शार्कर (री *f.*), आश्मिक (की *f.*), शर्करिल, श(शा)र्करिक (की *f.*), (*s.*) in comp.; 's. seat' शिलासनं. 3 प्रस्तरनिभ-तुल्य-समान.

Stool, *s.* पीठ:-ठं, आसनं, पाद-चरण-पीठं. 2 उच्चार:, रेक:, मलोच्चार:, पुरीषोत्सर्ग:; 'to pass s. s' उच्चर् 1 P, पुरीषं उत्सृज् 6 P.

Stoop, *v. i.* गात्रं नम् c. or आवृज् 10, नम् 1 P, अव-आ-प्र°-,प्रह्वीभू 1 P, नम्रीभू, प्रवणीभू. 2 **Condescend,** q. v. -*v. t.* आवृज्, नम् c., नम्रीकृ 8 U, प्रह्वीकृ. -*s.*,**-ing,** *s.* नति *f.*, नमनं, आ-अव-प्र°. **-ing,** *a.* नत, प्रवण, प्रणतिप्रवणं; अव-,नम्र, प्रह्व, नतांग, अवनतकाय, प्रणताशिरस्; 'a s. posture' नति:, वैतसी वृत्ति:.

Stop, *v. t.* वि-,स्तंभ् 9 P or c., अव-स्था c. (स्थापयति), रुध् 7 U, नि-प्रति-अव-रु°, प्रति-बंध् 9 P; पि-धा 3 U (ears &c.); 's.s the chariot' रथं स्थापयति. 2 निवृ c., बाध् 1 A, प्रति-वि-हन् 2 P, प्रति-नि-षिध् 1 P, विच्छिद् 7 P. 3 निवृत् c, विरम् c., विश्रम् c., प्र-उप-शम् c. -*v. i.* प्र-उप-शम् 4 P, विरम् 1 P, निवृत् 1 A; स्था 1 P, अवस्था (A), निश्चल-स्थिर-स्तब्ध-रुद्ध-गति- *a.* भू 1 P; *See* **Cease, End.** 2 विश्रम् 4 P (rest); 'the evil does not s. here' नैतावता पीडा निष्क्रामति (S. 2). -*s.*, **-ping,** *s.* स्तंभ:, स्तंभनं, प्रतिष्टंभ:, प्रतिबंध:, अव-नि-प्रति-रोध:, पिधानं; विष्टंभ:, गमननिवृत्ति *f.*, विराम:; 'put a s. to' *See* (*v.*), often by विरम् with abl. 2 अव-,स्थिति *f.*, विराम:, प्रशांति *f.*, विश्रांति *f.*, वि-,निवृत्ति:, विच्छेद:, भंग:, विरति *f.*, 3 (In music) यति *f.*, अवसानं, विराम:. 4 विराम:,-चिह्नं,-बिंदु:, अवसानचिह्नं. **-page,** *s.* प्रतिबंध:, प्रतिष्टंभ:; *See* (*s*); 's. of any organic function' अव-,रोध:, आ-,नाह:, बंध:. **-per,** **-Stopple,** *s.* रोध:, अवष्टंभ:.

Storax, *s.* शिलाजं, शिलाकुसुमं-पुष्पं.

Store, *v. t.* संभृ 1, 3 U, समाहृ 1 P संचि 5 U, संग्रह् 9 P, संपूर् 10, प c. -*s.*, **-age;** *s.* संभार:, संचय:, राशि:, संग्रह:, समाहार:, सामग्री, निधि:, निधानं, कोश:-ष:, संघात:. 2 **Store-house,** q. v.; 's.-house' कोष:, भांडारं; कोष्ठ:; 's.-keeper' कोषाध्यक्ष:-पाल:; 's.-house of corn' कुशूल:, धान्यकोष्ठ:.

Stork, *s.* सारस:, बक:, बलाक:, क्रौंच:.

Storm, *s.* वात्या, चंडवात:, प्रभंजन:, महा-अति-वात:, वात्यावेग:, प्रकंपन:, दुर्दिनं, झंझावात: (with showers). 2 संरंभ:, संक्षोभ:. 3 लंघनं, अवस्कंद:-दनं. -*v. t.* आ-अव-स्कंद् 1 P, लंघ् 1 A, 10, सहसा आपत् 1 P or ग्रह् 9 U or रुध् 7 U. -*v. i.* **Rage,** q. v. **-y,** *a.* प्रचंडवात वात्याकुल, वाताहत, पवनक्षुब्ध, अतिवातविशिष्ट; ex. by (*s.*); 'it is s. weather to-day' अद्य प्रभंजन: सर्वतो वाति, दुर्दिनमद्य; 's. sea' क्षुब्धार्णव:. 2 संरब्ध, संक्षुब्ध, संक्षोभित.

Story, *s.* कथा, वृत्तांत:, आख्यानं, उपाख्यानं, उप-परि-कथा, आख्यायिका; 'historical s.' इतिहास: चरित्रं-तं; 'remaining only in s.' कथीकृत, कथावशेषीकृत, कथाशेष. 2 वस्तु *n.*, कथानकं (of dramas &c.). 3 भूमि *f.*; सप्तभूमिक: प्रासाद: 'a palace having 7 s. es'; 'ground s.' तलं; 's.-teller' कथक: **-ied,** *a.* सभूमि-मिक. 2 इतिहासप्रसिद्ध.

Stout, *a.* महा-स्थूल-काय, बृहच्छरीर, मांसल, स्थूलशरीर, प्रबल, महाबलं, बलवत्. 2 धीर, विक्रांत, शूर, प्रगल्भ (heart). **-ness,** *s.* शरीरस्थूलता, मांसलता.

Stove, *s.* चुल्लि-ल्ली *f.*, अधिश्रयणी, अग्निकुंडं, अश्मंत, उद्धानं, अंतिका.

Stow, *v. t.* (कोष्ठे) निविश् c., नि-धा 3 U, स्था c. (स्थापयति); *See* **Store,** also.

Straddle, *v. i.* प्रसारितजंघ-*a.* स्था 1 P.

Straggle, *v. i.* व्यभिचर् 1 P, विभ्रम् 1, 4 P, मार्गात् प्र-वि-चल् 1 P or च्यु 1 A or भ्रंश् 1 A, 4 P. **-er,** *s.* भ्रष्ट-भ्रांत-पथः, व्यभिचारिन् *m.*, नष्टपथः.

Straight, *a.* सरल, ऋजु, अजिह्म, अकुटिल, अनुग्र, अवक्र, समरेख, अनराल, प्रगुण, अंजस, 'the s.-stemmed lotus' अनरालनालनलिनी. *-adv.*, 's.-way' सपदि, अनंतरमेव, सद्यः, तत्कालं, अविलंबितं. 2 सरलं, अवक्रं, ऋजु. **-en,** *v. t.* ऋजुकृ 8 U, सरलीकृ. **-ly,** *adv.* सरलं, अवक्रं, ऋजुतया, &c. **-ness,** *s.* सारल्यं, आर्जवं, अकौटिल्यं. **-Straightforward,** *a.* ऋजु, सरल, शुचि, ऋजु-सरल-प्रकृति; *See* **Honest.** **-ly,** *adv.* सरलं, अवक्रं, ऋजुतया; स्पष्टं, व्यक्तं. **-ness,** *s.* आर्जवं, सारल्यं, दाक्षिण्यं.

Strain, *v. t.* आयस् c., अत्यंतं आकृष् 1 P; 's. every nerve' सर्वात्मना प्रयत् 1 A. 2 अत्यंतं तन् 8 U, अतितानेन अभिहन् 2 P; *See* **Sprain.** 3 (Juice) निष्पीड् 10, निर्गल् c., निष्कृष्. 4 (Filter) स्रु c., पू 9 U, विमलीकृ 8 U, स्रु c.; 'should s. through a cloth' स्रावयेत् पटात्. 5 (To the bosom) *See* **Clasp**; 'this is not the time to s. courtesies' अत्युपचार-पूर्वकं-उपचारं-व्यवहर्तुं नायं समयः. *-v. i.* अत्यंतं प्रयत् or उद्यम् 1, A or आयस् 1,4 P or व्यव-सो 4 P. 2 निर्गल् 1 P, स्रु 1 P. *-s.* आयासः, अतियत्नः-श्रमः. 2 प्रवहणं, अत्यंताकर्षः; *See* **Sprain.** 3 तानः, संततस्वरः. 4 आ-,कर्षणं, वितति *f.* 5 रीति *f.*, प्रकारः. 6 विषयः. **-ed,** *a.* वितत, आ-,कृष्ट &c. 2 (Meaning) क्लिष्ट, नेयार्थ. **-er,** *s.* चालनी, चालनि, शोधनी.

Strait, *a.* संकट, संबाध, अनायत, संकुचित, *See* **Narrow.** *-s.* कृच्छ्रं, कष्टं, संकटं, दुर्दशा, कष्टावस्था, संकटावस्था; 'in s. s' कृच्छ्रगत, कष्टापन्न. 2 सामुद्रधुनी, संकटमार्गः. **-en,** *v. t.* पीड् 10, सं-,बाध् 1 A, संकुच् 1 P; 's. ed circumstances' (अर्थ-) कृच्छ्रं, कष्टं, दुर्गति *f.*

Strand, *s.* तीरं, तटं, कूलं. *-v. t.* उत्कूलयति (D.). *-v. i.* तीरं म्रस् 5 P.

Strange, *a.* अपूर्व, चि-,चित्र, अद्भुत, आश्चर्यभूत, 'what is s. in this' किमत्र चित्रं.

2 विदेशीय, परकीय; *See* **Foreign.** 3 अप-वि-रूप, विलक्षण, असंगत, असंबद्ध, अलौकिक (की *f.*), असंभव. 4 अपरिचित, असंस्तुत, अज्ञातपूर्व. *-interj.* चित्रं, अहोबत चित्रं, आश्चर्यं. **-er,** *s.* आगंतुकः, अभ्यागतः. 2 वैदेशिकः, विदेशीयः, वैदेश्यः. 3 परः, परपुरुषः, पारक्यः, अपरिचितः, अन्यजनः. 4(*a.*) अपरिचित, अनभ्यस्त, अनभिज्ञ, अज्ञात; 'we are s. s to the use of chariots' रथं अनभ्यस्तरथचर्याः (U. 5). **-ly,** *adv.* अद्भुतं, चित्रं. **-ness,** *s.* अपूर्वता, वैचित्र्यं, वैलक्षण्यं, &c.

Strangle, Strangulate, *v. t.* कंठं निपीड्य-श्वासं निरुध्य-मृ c. or व्यापद् c., गलहस्तयति (D.); श्वासं अव-नि-रुध् 7 U. **-ing, -ion,** *s.* गलपीडनं, गल-हस्तः, श्वासावरोधः.

Strangury, *s.* अश्मरी, मूत्रकृच्छ्रं.

Strap, *s.* चर्मपट्टः-बंधः, वरत्रा, वध्री, नध्री. *-v. t.* चर्मपट्टेन बंध् 1 P or तड् 10.

Stratagem, *s.* उपायः, कल्पना, युक्ति *f.*, अप-व्यप-देशः, छलं, कपटोपायः, छद्मन् *n.*

Strategy, *s.* युद्धकौशलं, समरपाटवं, व्यूहरचनाविद्या-नैपुण्यं.

Stratum, *s.* स्तरः, फलकः-कं, आ-सं-स्तरः.

Straw, *s.* पलः, पलालः-लं, नालः-लं, तृणं (fig. also), शुष्कधान्यं; 'to make s. of', 'not to care a s. for' तृणाय-तृणं-मन् 4 A; 'a man of s.' तृणमूर्ति *f.*; कल्पितपुरुषः.

Stray, *v. i.* (यूथात् &c.) भ्रंश् 1 A, 4 P, व्यभिचर् 1 P, (मार्गात्) प्र-,विचल् 1 P, प्र-,भ्रंश्. 2 प्रमद् 4 P, स्खल् 1 P; *See* **Err, Mistake.** **-ed,** *a.* प्र-,भ्रष्ट, च्युत, विचलित, भ्रांत, मार्गभ्रष्ट, नष्टपथ, यूथभ्रष्ट. 2 (Thoughts) निरन्वय.

Streak, *s.* रे(ले)खा, राजि *f.*; 's. of lightning' विद्युल्लेखा. *-v. t.* रेखाभिः अंक् 10, चित्रीकृ 8 U; 's. ed with gold' कनकरेखाभिः सनाथीकृत, हेमरेखांकित. **-ed,-y,** *a.* रेखांकित-चिह्नित, चित्र, चित्रित, शबल.

Stream, *s.* स्रोतस् *n.*, सरित् *f.*, नदी. 2 ओघः प्रवाहः, रयः, ओघः, प्रवृत्ति *f.*, वेला, वेगः, प्रवाहः, धारा-रः; 's. of rain' पर्जन्यधारा. *-v. i.* स्रु 1 P, सततं प्रवह् 1 P or स्रु 1 P. 2 **Radiate, Extend,** q. v. **-er,** *s.* पताका, केतुवसनं. **-ing,** *a.* संतत or निरंतरप्रवाहिन् or स्राविन्. **-let,** *s.* क्षुद्र-क्षु-सरित्, अल्पस्रोतः.

Street, *s.* पथिन् *m.*, मार्गः, वीथि-थी *f.*, रथ्या, प्रतोली, विशिखा; 'royal s.' राजमार्गः-पथः, महापथः, संसरणं.

Strength, *s.* *See* under **Strong.**

Strenuous, *a.* सोत्साह, सोद्यम, सोद्योग, महोद्यम; अविरत, अविश्रांत, अभिनिविष्ट, संतत. **-ly,** *adv.* सोत्साहं, प्रयत्नैः, अविरतं. **-ness,** *s.* उत्साहः, उद्योगः, उद्यमः, उद्यमसातत्यं; *See* **Energy, Industry.**

Stress, *s.* भारः, भरः; गुरुत्वं, माहात्म्यं, गौरवं, प्रभावः, बलं; 'I lay s. on this point' इममर्थं गुरुप्रयोजनं-गुरुं मन्ये.

Stretch, *v. t.* विस्तृ-स्तृ c., प्र-वि-तन् 8 U, आयम् 1 P, दीर्घीकृ 8 U; (hand) प्रसृ c., लंब् c. **-v.** *i.* प्र-वि-तन् pass., विस्तृ pass., प्र-सृ 1 P, प्र-,लंब् 1 A; *See* **Extend** also. **2 Exaggerate,** q. v. **-s.** विततिं *f.*, विस्तारः, विस्तृतिः, आयामः, प्रसारः-रणं. 2 प्रयत्नः, प्रयासः, उद्यमः. **3** विषय, प्रसरः. 4 वाङ्गुपचयः, अत्युक्ति *f.* **-er,** *s.* शिबिका.

Strew, *v. t.* अव-प्र-विकृ 6 P, स्तृ 9 U, सं-आ-परि-°, आच्छद् 10.

Striate, *a.* रेखांकित.

Strict, *a.* अशिथिल, दृढ, नियत. 2 अनतिक्रमणीय, अनुल्लंघ्य; *See* **Peremptory. 3** परुष, निष्ठुर, कठिन, कठोर, तीक्ष्ण, तीव्र. 4 सूक्ष्म, निपुण; 'on the s.-est search' अतिनिपुणमन्विष्यापि. **-ly,** *adv.* अशिथिलं, परुषं, सनिश्चयं, परिच्छेदनिष्ठुरं, दृढं; 's. true' सर्वथा सत्य. **-ness,** *s.* अशैथिल्यं, सूक्ष्मता, काठिन्यं, &c.

Stricture, *s.* निंदा, भर्त्सना, आक्षेपः; *See* **Censure. 2** प्रस्रावरोधः, मूत्रग्रंथिः.

Stride, *s.* विक्रमः, पादन्यासः, दीर्घविक्रमः. **-v.** वि-परि-क्रम् 1 U, 4 P, लंघ् 1 A, 10, आ-अध्या-रुह् 1 P, आ-अध्या-क्रम्.

Strife, *s.* कलिः, विवादः, कलहः, विप्रतिपत्ति *f.*, विरोधः, द्वंद्वं.

Strike, *v. t.* हन् 2 P, प्र-अभि उप-°, आहन् 2 U, तुद् 6 P, प्रहृ 1 P (with loc.), तड् 10; आस्फल् c. (water); 's. on the face' मुखं चपेटां दा 3 U, हस्ततलेन प्रहृ. 2 पिड् c, पीड् 10, अर्द् 1 P or c.; 'famine-s.en' दुर्भिक्ष-पीडित-विद्रुत. 3 (With wonder &c.) उपहन्, चकित-a. कृ; oft. by चकित-सविस्मय; 'was struck with the beauty of his horns' शृंगशोभां दृष्ट्वा विस्मयमापेदे. 4 वद् c., नद् c., ध्वन् c. (lute &c.). 5 जन् c., उत्पद् c.; 's. a fear in the mind' चित्ते भयं जनयति; 's. ing deep root' स्थिरबद्ध-प्ररूढ-मूल; 's. sail' वातवस्त्रं अवपत् c. or अवरुह् c., निवसी-स्तब्धी-कृ; 's. blind' अंधीकृ; 's. accounts' गणनां समीकृ; 'it struck me as wonderful' अद्भुतमिव मां प्रतिबभौ; 'he was struck with wonder' तस्य हृदयं परस्पर्श विस्मयः (Ka. 80), आश्चर्यचकितो बभूव; 'being used in its most general sense, it easily s.s the mind' तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति, प्रसिद्धिबलेन प्रथमतरं प्रतीयते (S. B. 135, 137). **-v.** *i.* (Against) संघट्ट् 1 A or c., आस्फल् 1 P; *See* **Dash. 2** संभूय कर्म परित्यज् 1 P; कार्यनिवृत्तिसंकेतं कृ. **-down,** नि-अव-पत् c., हन् c. (ग्रातयति), आहत्य भूमौ पत् c. **-for,** प्र-स्था 1 A, प्र-या 2 P, निर्गम् 1 P; *See* **Start. -off,** वि-,नश् c., वि-, लुप् c.; अप-व्या-मृज् 2 P or c., उच्छिद् 7 P. **-out,** (Fire) घर्षणेन-संघट्टनेन जन् c. **2** लुप् 6 P or c., नश् c., उच्छिद्, व्यामृज्; *See* **Efface. 3** कल्प् c., चिंत् 10, युज् 7 U, 10, निरूप् 10. **4** शुभ्रयति (D.). **-through,** निर्भिद् 7 P, प्रविश् 6 P, प्रविश्य निर्गम्. **-up,** आरभ् 1 A, प्रस्तु 2 U; *See* **Begin. -s.** युगपत् or संभूय कार्यनिवृत्तिसंकेतः. **-ing,** *a.* चि-, चित्र, आश्चर्यजनन (नी *f.*,), अद्भुत, विस्मयावह, आश्चर्यभूत, हृदयग्राहिन्, चित्तहारिन्. **-ingly,** *adv.* मनोहरं, विचित्रतया, अद्भुतं, अतीव, हृदयग्राहितया. **-Stroke,** *s.* आ-अभि-घातः, आहति *f.*, प्रहारः, ताडनं, पातः; 's. of a thunder-bolt' वज्रपातः, अशनिपातः. **2** रेखा, लेखा. **3** आक्रमः, अवतारः, आवेशः, लंघनं; 'sun-s.' आतपलंघनं, सूर्याभिघातः. **4** प्रयत्नः, आकस्मिकयत्नः; 's. of policy' नीत्युत्कर्षः, नयनिपुणता. **-v.** *t.* (पाणिना-हस्तेन) परामृश् 6 P, स्पृश् 6 P; (परामृशन् हर्षजडेन पाणिना R. III. 68); शनैः मृज् 2 P or समालभ् 1 A, हस्तेन लल् 10.

String, *s.* रज्जु *f.*, गुणः, तंत्रं-त्री (of lutes &c.), तंतुः, सूत्रं, दामन् *f. n.*, शुल्बं; *See* **Rope;** (of a bow) ज्या, गुणः, मौर्वी, शिंजिनी. **2** परंपरा, माला, पंक्ति *f.*, श्रेणि-णी *f.*, आवलि-ली *f.*; 's. of pearls' मुक्तावली, मुक्ताहारः-सरः. **3** (Human) शिरा. **-v.** *t.* सं-ग्रंथ् 9 P, गुं(गु)फ् 6 P, वि-,रच् 10, सं-,दृभ् 6 P, 10, सूत्र् 10. **2** तंत्रीभिः-गुणैः-बंध् 9 P; (a bow) अधिज्यं कृ; धनुषि ज्यां आरुह् c. or आतन् 8 U; 'a bow strung' अधिज्य-आततज्यं-आरोपितज्यं-धनुः; 'a string strung tight on a bow' धनुषि आतता मौर्वी (R. I. 19). **-ed,** *a.* तंत्रिन्, तंत्री-गुण-विशिष्ट, तंतुयुक्त. **-y,** *a.* सूत्रिन्, सूत्र-तंतु-मय (यी *f.*).

Stringent, *a.* तीक्ष्ण, कठोर, दृढ, अशिथिल.

Strip, *v. t.* अप-,हृ 1 P, अप-नी 1 P, निर्-हृ; gen. by अप, निर्, वि in comp.; 's. of clothes' विवस्त्रयति (D.), निर्वस्त्रीकृ 8 U, उच्छद् 10; 's. of bark' विवल्कयति (D.); निरवयति, निर्दलीकृ, &c. **-s.** खंडः

ई, पद्मा. -ped, a. अप-हृत, अपनीत. 2 विवस्त्र, विवस्त्रीकृत, नग्नीकृत; हृतवस्त्र-वेष; 's of one's all' हृतसर्वस्व.

Stripe, s. रे(ले)खा. 2 दीर्घांशुः. 3 कशाघात-प्रहारः. -v. t. रेखाभिः चित्रयति (D.) or अंक् 10. 2 कशया तड् 10 or प्रहृ 1 P.

Stripling s. शिशुः, अर्भकः, डिंभः, बालः, किशोरः.

Strive, v. i. प्र-,यत् 1 A, घट् 1 A, उद्यम् 1 A, चेष्ट् 1 A, व्यव-सो 4 P, प्रवृत् 1 A. 2 स्पर्ध् 1 A. 3 (Against) विरुद्ध् 1 A, विरुध् 7 U, कलहं कृ 8 U; *See* **Contend.**

Stroke, s. *See* under **Strike**.

Stroll, v. i. (आलस्येन) विचर् 1 P, परि-क्रम् 1 U, 4 P, विहृ 1 P, परिभ्रम् 1, 4 P. -s. परिक्रमः-मणं, विहारः, परि-,भ्रमणं, यथेष्टचारः. -er, s. पथिकः, यथेष्टविहारिन् m.

Strong, a. बलिन्, बलवत्, सबल, वीर्यवत्, शक्तिमत्, समर्थ, ऊर्जस्वल, ओजस्विन्, प्रबल, ऊर्जित; 's.-minded' मनस्विन्, धीरप्रकृति. 2 क्षम, दक्ष, कुशल. 3 दृढ, स्थिर (resolution); उग्र (smell). 4 तीव्र, तीक्ष्ण, चंड, प्रखर, अति pr. 5 गाढ, उत्कट, प्रबल; *See* **Intense**. 6 वीर्यवत्, प्रतापवत्, गुणावह, गुणकारिन् (medicine); 'to grow s.' प्रबलीभू, पुष्पूर्छ् 1 P; '10000 s.' अयुतसंख्याक; 's.-bodied,' 's.-built' उपचितगात्र, मांसल, दृढांग, दृढावयव; 's.-hold' दुर्ग, कोटः. -ly. adv. बलवत्, दृढं, गाढं, परमं, उग्रं, उत्कटं, &c. -**Strength**, s. बलं, वीर्यं, शक्ति f., सामर्थ्यं, तेजस् n., प्रभावः, ओजस् n, ऊर्जः, सत्त्वं; वि-पराक्रमः; क्षमता, बलवत्ता, प्राबल्यं, विभवः; 'the s. of mind' धीशक्तिः, बुद्धि-प्रभावः, मतिविभवः; 'what is the s. of the enemy' कियत्संख्यकाः शत्रवः; 'on the s. of' अवलंब्य. -en, v. t. प्रबलीकृ 8 U, बलं दा 3 U or वृध् c. 2 दृढीकृ, द्रढयति (D.): *See* **Confirm, Establish**; निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति (U. 2) 's. s the belief that it is the same'; 'Sringāra s. ed by Karuṇā' करुणानुप्राणितः शृंगाररसः -v. i. प्रबलीभू 1 P, प्र-उप-चि-pass.; वि-प्र-वृध् 1 A; प्ररुह् 1 P. -ing, a. बलवर्धन (नी f.), बलप्रद.

Structure, s. निर्माणं, संस्थानं, विधानं, रचन-ना. 2 आकारः, रूपं. 3 मंदिरं, भवन.

Struggle, v. i. प्रयत् 1 A प्रयासं-यत्नं-कृ 8 U, चेष्ट् 1 A; शार्दूलः पशुमिव हन्मि चेष्टमानं (S. 6) 'an animal s.-ing, while being killed' &c. 2 युध् 4 A, संयत्; *See* **Fight.** -ing. s. प्रयासः, प्रयत्नः, वि-चेष्टा-चेष्टितं, अतिवलनः; मुक्तप्रयत्न मां सलिल-

विप्लुतपायवत् (Ka. 38) 'me who had ceased s.' &c. 2 युद्धं, कलहः, विग्रहः, द्वंद्वं.

Struma, s. विस्फोटः-टकः.

Strumpet, s. *See* **Prostitute.**

Strut, v. i. साटोपं-उद्धतं-धीरोद्धतं-परिक्रम् 1 U, 4 P, सगर्वं चल् 1 P. -s. साटोप-उद्धत-सगर्व-गति f. -ting, a. सगर्वगति, साटोपगामिन्.

Stubble, s. नालः-ली, लूनशस्यनालः.

Stubborn, a. दुर्दांत, दुर्दम, प्रतिनिविष्ट, अवश्य, अविनेय, मत्त्य; *See* **Obstinate.**

Stucco, s. सुधा, चूर्णलेपः. -v. t. सुधया लिप् 6 P. -ed. a. सुधालिप्त.

Stud, s. गंडः; (of horses) अश्वाः, आश्वं, अश्वीयं, वाडवं; (place) अश्वशाला, मंदुरा. -v. t. उत्-,खच् 10 (खचयति), प्रतिबंध् 9 P, प्रतिवप् 1 P, अनुवप् 4 P; 'sky s. ed with stars' तारकितं नभः; 's. ed with gems' रत्नखचित, रत्नानुविद्ध-प्रत्युप्त &c.

Study, v. t. अधि-इ 2 A. अधिगम् 1 P, (acquire by s.); शिक्ष् 1 A; पठ् 1 P; भावृत् c., अभ्यस् 4 U. 2 ध्यै 1 P, चिंत् 10, कल्प् 10; प्रयत् 1 A, विमृश् 6 P. -s. अध्ययनं, अभ्यासः अभ्यसनं, शिक्षणं, पठनं, पाठः, अधिगमः-मनं; 's. of the Vedas' वेदाध्ययनं, उपाकरणं; 'close s. अविरताभ्यासः, अनु-परि-शीलनं; 'desultory s.' चंक्रमणं. 2 अध्ययनशाला-आगारं, ग्रंथकुटी. 3 पाठः, अध्ययनविषयः. 4 चिंतनं, कल्पना, विचारः. -ent, s. अध्येतृ m., छात्रः, शिष्यः, अधीयानः, विद्यार्थिन् m: 'a religious s.' ब्रह्मचारी, व्रती, लिंगी. -ied, a.: पूर्वपठित, सुनिश्चित, पूर्वनिर्णीत, चिंतित-निर्णीत-पूर्व, कामतः कृत. -ious, a. अध्ययनपरायण-तत्पर-शील-आसक्त, विद्याप्रसित-अभिनिविष्ट. 2 उत्सुक, व्यवसायपर, अध्यवसायिन्; 'of s. habits' व्यवसायशील. -iously, adv. विद्याभ्यासंगेन; संकल्प-निर्णय-पूर्वं, कामतः. -iousness, s. अध्ययन-विद्या-आसक्ति f.-अभिनिवेशः, विद्याभ्यासंगः.

Stuff, s. वस्तु n., द्रव्यं, प्रकृति f., पदार्थः. 2 पटः, वस्त्रं, वसनं; *See* **Cloth.** 3 गृहोपस्करः, गृहसामग्री-द्रव्याणि-भांडानि. 4 तुच्छ-कुत्सित-द्रव्यं. 5 अनर्थकप्रलापः. -v. t. अत्यंतं पूर् 10, अतिशयेन तृप् c. 2 **Crowd, Cram.** q. v.; 's. ed with cotton' कार्पासपूरित. -v. i. आतृप्ति पृ pass. -ing, s. पूरणं &c.

Stuffy, a. निर्वात.

Stultify, v. t. मूढीकृ 8 U, मूर्खवत् आचर् c.; (oneself) मूर्खवत् आचर् 1 P.

Stumble, v. i. प्र-,स्खल् 1 P, विस्तीर्, (मार्गे पदानि खलु ते विषमीभवंति S. 4).

प्र-वि-चल् 1 P, च्यु 1 A. —*v. t.* प्र-,स्खल् c. (स्खलयति). —*s.* **-ing,** *s.* स्खलनं, स्खलितं; ' s. ing-block ' गतिकुंठनस्थानं; ' this is a s. ing-block to all ' अत्र सर्वे स्खलंति; अत्र सर्वेषां गतिः कुंठिता भवति.

Stump, *s.* कंदः-दं, स्थाणुः. —**y,** *a.* ह्रस्वस्थूल.

Stun, *v. t.* बधिरीकृ 8 U, (आक्रोशेन दिशो बधिरीकृताः); (persons) आघातेन-प्रहारेण-जडीकृ 8 U, मूर्च्छां प्राप् c. or जन् c.; ' s. the ears ' कर्णविवरं-कर्णपुटं जर्जरीकृ or जर्जरयति (D.) or स्फुट् c. or उपहन् 2 P, जर्जरितकर्णविवरः (Ka. 27), जर्जरीकृतकर्णपुटः 'the ears being s. ed' &c.; ' he was s.-ed by the noise ' निनादश्रवणेनामूर्च्छत्. —**ned,** *a.* आघात-प्रहार-मूढ-जड-मोहित, जर्जरितकर्ण, बधिरीकृत. —**ning,** *a.* कर्णोपघातिन्, श्रवणशक्तिहारिन्.

Stunt, *v. t.* (वृद्धिं) स्तंभ् 9 P or c., रुध् 7 U, वामनी-खर्वी-कृ 8 U. —*s.* वृद्धिरोधः-स्तंभः. —**ed,** *a.* पृश्नि, अल्पतनु, वामनाकृति, रुद्धवृद्धि.

Stupefy, *v. t.* जडीकृ 8 U, जडयति (D.), मुह् c., सं-स्त्या-°, निष्पंदीकृ, सं-,स्तंभ् c. —**action, Stupor,** *s.* जाड्यं, जडिमन् *m.*, जडता-त्वं, मोहः, सं-स्त्या-°, इंद्रियस्वापः-मोहः-स्तंभः. —**ing,** *a.* स्त्या-, मोहिन्, मोहकारिन्, स्तंभक. —**Stupid,** *a.* जड, मूढ, मूर्ख, मंद, मूढ-स्थूल-जड-मंद-धी-मति-बुद्धि, निर्बुद्धि, दुर्बुद्धि, अविज्ञ, अज्ञ; ' a s. mistake ' अतिगर्हणीयः प्रमादः. —**ity,** —**ness,** *s.* जाड्यं, मौर्ख्यं, मूढता, जडिमन् *m.*, अज्ञानं. &c. —**ly,** *adv.* जाड्येन, मूर्खतया, मूढवत्.

Stupendous, *a.* अतिविशाल, अद्भुत, आश्चर्य-विस्मय-कर (री *f.*), विस्मयोत्पादक.

Sturdy. *a.* कठिन, कठोर; दृढांग, प्रबल; *See* **Stout.**

Stutter, *v. i.* *See* **Stammer.**

Sty, *s.* शूकरशाला.

Style, *s.* रीति *f.*, प्रकारः, पद्धति *f.*, वृत्ति *f.*, सरणि *f.* 2 भाषासरणिः, लेखनपद्धतिः; (of speaking) वाग्वृत्तिः-व्यापारः-सरणिः. 3 संज्ञा, आख्या, ख्याति *f.* 4 लेखनी, कलमः. 5 शलाका, कीलः; शंकुः(of a dial). —*v. t.* अभि-धा 3 U, वच् 2 P, संज्ञां दा 3 U, कृत् 10; *See* **Name, Call;** ' s. ed Kakutstha ' ककुत्स्थ इत्याहितलक्षण (R. vi. 71), ककुत्स्थसंज्ञ &c. —**ish,** *a.* शिष्टजनमत, सभ्याचारानुरूप.

Styptic, *a.* रक्तस्तंभन, रक्तस्रावरोधिन्. —*s.* रक्तस्तंभनं-अवरोधः.

Styx, *s.* वैतरणी, प्रेतनदी.

Suasion, *s.* *See* **Persuasion** under **Persuade.**

Suave, *a.* सुशील, सभ्य, मधुर, मनोज्ञ. —**ity,** *s.* माधुर्यं, मनोज्ञता, स्वादुता.

Subacid, *a.* ईषदम्ल.

Subdivide, *v. t.* प्र-,विभज् 1 U, अंशांशान् कृ 8 U. —**Subdivision,** *s.* प्रभागः, प्रविभागः; उपशाखा, प्रति-प्र-शाखा, उपांगं, अवयवः.

Subdue, *v. t.* वशं नी 1 P, वशीकृ 8 U, वि-परा जि 1 A, अभि-परा-भू 1 P, दम् c. (दमयति), स्वायत्तीकृ, स्ववशे स्था c. (स्थापयति) 2 (Passions) जि, सं-नि-यम् 1 P, निग्रह् 9 P, दम् c., वशं नी; *See* **Control.** —**er,** *s.* जेतृ *m.*, दमनकारिन्. 2 वशिन् *m.* —**ing,** *s.* वि-,जयः, दमः-मनं, अभिभवः, नि-सं-यमः, निग्रहः, &c.

Subjacent, *a.* अधोवर्तिन्.

Subject, *s.* प्रजा, प्रकृति *f.* (usually in pl.). 2 विषयः (विषयिन् *m.*, as opp. to object); प्रकरण, प्रस्तावः, प्रसंगः, अर्थः, पद, स्थानं, आस्पदं, भूमि *f.*, अधिष्ठानं, आधारः, आश्रयः, आशयः, भाजनं. 3 नायकः, कथापुरुषः-नायकः. 4 कर्ता (in grammar). 5 साध्यं; ' s. in hand ' प्रकृतं, प्रस्तुतं, प्रस्तुतार्थः; ' this chapter is on the s. of Sānkhya doctrines ' सांख्यवादविषयकोऽयमध्यायः. —*a.* वशवर्तिन्, वशग, उपजीविन्, आश्रित; निघ्न, वश, अधीन, आयत्त, तंत्र in comp. 2 (Liable) अधीन, आयत्त, &c., अर्ह, पात्रं, आस्पदं in comp.; *See* **Liable;** ' one that is born is s. to death ' जातेन खलु मर्तव्यं, जातस्य हि ध्रुवो मृत्युः; ' not s. to anger ' अनायत्तो रोषस्य (Ka. 45); so अवशो विषयाणां, अदत्तावकाशो मत्सरस्य (*ibid.*); ' s. to disease ' रोगाधीन, नित्य-सदा-रोगिन्, रोगपात्रं, &c. —*v. t.* वशीकृ 8 U, अभिभू 1 P; *See* **Subdue.** 2 पदं नी 1 P, अधीनी-आयत्ती-आस्पदी-कृ; ' you have s.-ed yourself to trouble ' क्लेशस्यात्मा पदमुपनीतः (S. 1); ' you have s. ed yourself (soul) to great penance ' आयोजितस्तपासि महत्यात्मा (Ka. 173); अयत्नेनैवोपहासास्पदतामीश्वरो नयति जनं (Ka. 151) ' easily s. s to ridicule ' &c.; उपहासास्पदं कृ, &c. —**ion,** *s.* वशः-शं, वशता, निघ्नता, तंत्रता, आयत्तत्वं, अधीनता, &c. in comp.; ' s to another ' परवशता, पराधीनता, परवत्ता, &c. —**ive,** *a.* विषयिन्, आधिकरणिक.

Subjoin, *v. t.* अनुबंध् 9 P, आयुज् 7 U, 10; अधः लिख् 6 P or लिखिख् 6 P.

Subjugate, *v. t.* वशीकृ 8 U, अभिभू 1 P, परा-वि-जि 1 A, भंज् 7 P, करदीकृ; *See* **Subdue.** —**ion,** *s.* दमन-मनं, जयः, पराभिभवः, भंगः, नियमः, निग्रहः; *See* **Control** also.

Sublimate, *s.* रसकर्पूरः-पुष्पं. –*v. t.* बाष्पीकृ 8 U.

Sublime, *a.* उन्नत, अत्युच्छ्रित, उत्कृष्ट, विशिष्ट, गुरु; *See* **Lofty;** उदात्त, प्रौढ (sentiment &c.). –*v. t.* **Exalt,** q. v. **-ity,-ness,** *s.* तुंगता, उन्नति *f.*, अनुभावः, प्रौढि *f.*, अत्युत्कर्षः, गौरवं; 's. of meaning' अर्थगौरवं, उदात्तार्थः.

Subliminal, *a.* बोधातीत, अव्यक्त.

Sublunary, *a.* ऐहिक-सांसारिक-(की *f.*); *See* **Worldly.**

Submarine, *a.* समुद्रस्थ-गत; 's. fire और्वः, वडवानलः, वाडवः.

Submerge, *v. t.* नि-,मस्ज् c. (मज्जयति), आप्लु c. –*v. i.* नि-,मस्ज् 6 P, अवगाह् 6 A; *See* **Plunge.** –**Submersion,** *s* निमज्जनं, आप्लावः, प्लावनं.

Submit, *v. i.* प्रणम् 1 P, वशः गम् 1 P, शरणं गम् or या 2 P or प्रपद् 4 A; (to order &c.) अनुरुध् 4 A, अनुवृत् 1 A, अनुपा c. (पालयति); *See* **Obey;** सह् 1 A, क्षम् 1 A, मृष् 4 P, 10; oft. ex. by प्रमाणं; आर्यमिश्राः प्रमाणं (M. 1) 'I s. to your honor's opinion (decision)'. 2 सविनयं वद् 1 P or प्रार्थ् 10 A. –*v. t.* सविनयं ऋ c. (अर्पयति) or निक्षिप् 6 P or निर्दिश् 6 P; *See* **Refer.** –**Submission,** *s.* प्रणति *f.*, वशता-त्वं. 2 अनुवृत्ति *f.*, अनुवर्तनं, अनुरोधः. 3 क्षमा, क्षांति *f.*, सहिष्णुता. –**Submissive,** *a.* वश्य, प्रणतिप्रवण, वशग, वशवर्तिन्, विधेय. अनुविधायिन्, आज्ञाकर (री *f.*). 2 सविनय, नम्र, दीन. **-ly,** *adv.* सविनयं, नम्रतया, प्रार्थनापूर्वं, प्रणतिपूर्वं.

Subordinate, *a.* अधीन, आयत्त. 2 अप्रधान, गौण (णी *f.*), अनुरूप; 'any thing s. to another' अप्रधानं, उपसर्जनं. –*v. t.* (to) अन्यापेक्षया गौण-अप्रधान-*a.* मन् 4 A. **-ion,** *s.* अधीनता, वशता, वश्यता, परवशता, पारतंत्र्यं, पराधीनता. 2 अप्राधान्यं, गौणता. **-ly,** *adv.* गौणतः, अप्राधान्येन, अनुरूपतः.

Suborn, *v. t.* (धनदानादिना) कूटसाक्ष्यं कृ c. (कारयति).

Subpœna, *s.* आह्वानपत्रं. –*v. t.* आह्वे 1 P.

Subscribe, *v.* (अधः) नाम लिख् 6 P or लिविश् c. हस्ताक्षरेण अंक् 10 or चिह्नयति (D.); *See* **Sign. 2 Agree,** q. v. 3 (द्रव्यं) दातुं प्रतिज्ञा 9 A, अंशं दा desid. (दित्सति-ते). **-er,** *s.* अंशदायिन् *m.* –**Subscription,** *s.* नामलिखनं-निवेशनं. 2 अंश-उद्धार-दानं; स्वांशः, उद्धारः. 3 (Of a paper) मूल्यं.

Subsequent, *a.* उत्तरकालिक, उत्तर, पश्चात् in comp.; पर, पश्चात्कालीन; अनु pr.; 's. rites' अनुकर्माणि, अनुगमनं, &c.; 's. mention' वक्ष्यमाणता. **-ly,** *adv.* तत ऊर्ध्वं; अनंतरं, तत उत्तरं; पश्चात्; (to) परं; ऊर्ध्वं, अनंतरं, परतः (with abl.); अनु pr.; 's. to the marriage' अनुविवाहं, विवाहात्परं, &c. –**Subsequence,** *s.* अनुगमनं-भावं.

Subserve. *v. i.* पुरस्कृ 8 U, वृध c., उपकृ; *See* **Promote.** –**Subservient,** *a.* आयत्त, अधीन, वश, निघ्न, तंत्र in comp. 2 उपयुक्त, उपकारिन्, सहयोगिन्. –**Subservience,-cy,** तंत्रता, अधीनत्वं. 2 उपयोगः, उपकारः.

Subside, *v. i.* शम् 4 P, प्र-उप-°, निवृत् 1 A, विरम् 1 P, वि-गम् 1 P; प्रसद् 1 P. 2 अधस्तले आसद्, अधः गम् or पत् 1 P.

Subsidy, *s.* (धनरूपं) साहाय्यं, करः. –**Subsidiary,** *a.* सहकारिन्, साहाय्यकारिन्, अनुकूल, मित्रभावापन्न. 2 **Subordinate,** q. v.; 'something s.' अप्रधानं, उपसर्जनं. गौणार्थः.

Subsist, *v. i.* भू 1 P, वृत् 1 A, विद् 4 A, अस् 2 P, स्था 1 P. 2 जीव् 1 P, आ-उप-°, प्राणयात्रां कृ, जीवितं-प्राणान् धृ 1 P, 10; *See* **Live.** **-ence,** *s.* सत्ता, अस्तित्वं, भावः, वृत्ति *f.* 2 आजीवः, वृत्तिः, आ-उपजीविका, प्राण-शरीर-यात्रा; *See* **Living.** **-ent,** *a.* जीविन्, सत्त्ववत्.

Subsoil, *s.* अधःस्तरः.

Substance, *s.* सारः, सत्त्वं, तत्त्वं; भावः, भावार्थः, सारांशः, तात्पर्यं, तात्पर्यार्थः; 'sum and s.' पिंडितः-निर्गलितः-अर्थः, निष्कर्षः; भावः; 'they are the same in s.' वस्तुतः समाः, अर्थतः तुल्याः. 2 (In Philosophy) द्रव्यं, पदार्थः. 3 वस्तु *n.*, द्रव्यं, अर्थः, मूर्तद्रव्यं. 4 संपत्ति *f.*, द्रव्यं, धनं, अर्थः, वित्तं, विभवः, वैभवं; *See* **Wealth.** –**Substantial,** *a.* सारवत्, ससार, समर्थ, घन. 2 तात्त्विक-सात्त्विक-वास्तविक-(की *f.*), यथार्थ, सत्य, वास्तव (वी *f.*) 3 धनिन्, सधन, समृद्ध, धनवत्; *See* **Wealthy.** **-ly,** *adv.* वस्तुतः, अर्थतः, तत्त्वतः, सारतः. –**Substantiate,** *v. t.* साध् c., उप-प्रतिपद् c., प्रमाणयति (D.), प्रमाणीकृ 8 U, सत्यापयति (D.), सत्याकृ, वि-भू c.; *See* **Prove.** **-ion,** *s.* उपपादनं, साधनं, सिद्धि *f.* –**Substantive,** *s.* विशेष्यं, सत्त्वं; 'dependent on the gender of the s.' विशेष्यनिघ्न, वाच्यलिंग. –*a.* सत्त्ववाचिन्.

Substitute, *s.* प्रतिनिधिः, प्रतिहस्तः-स्तकः, प्रतिपुरुषः; oft. by स्थानीय-*a.* or स्थाने वृत् 1 A. 2 (In grammar) आदेशः. –*v. t.* स्थाने-पदे-सं-,निविश् c. or प्र-नि-उप-युज् 7 A, 10 or उपकल्प् c.; तस्यैव भ्रातुः स्थाने सुग्रीवं कृतवान् (R. XII. 68) 's.-ed Sugriva in his place' &c.

'Adesa is one word s.-ed for another' आदेशो नाम शब्दांतरस्य स्थाने विधीयमानं शब्दांतरमभिधीयते (M. N. on *ibid.*). 2 परिवृत् c., उपसृज् 6 P. **-ion,** *s.* स्थाने नि-वेशनं-उपकल्पनं-विधानं.

Substratum, *s.* स्तरः, फलकः-कं. 2 आधारः, आश्रयः, स्थानं.

Subtend, *v. t.* अभिमुखं-संमुखं-वृत् 1 A or स्था 1 P (with gen.).

Subterfuge, *s.* छलं, छद्मन् *n.*, अप-व्यप-देशः.

Subterraneau, *a.* आंतर्भौम (मी *f.*), भूमि in comp.: भूम्यंतर्गत, गूढ: 's. place' भूमिगृहं, अंतर्भूमिः; 's. passage' सुरंगा, गूढमार्गः.

Subtile, Subtle, *a.* अतिसूक्ष्म; अणु,अतिलघु, निरवयव. 2 चतुर, विदग्ध, सूक्ष्मदर्शिन्, सूक्ष्म or कुशाग्र-मति or बुद्धि, मार्मिक (की *f.*), मर्मविद्. 3 Roguish, Sly, q.v. **-ly,** *adv.* सूक्ष्मं, सूक्ष्ममत्या. **-ness, -ty,** *s.* सूक्ष्मता, अणिमन् *m.*, अतिलाघवं. 2 वैदग्ध्यं, चातुर्यं.

Subtract, *v. t.* वियुज् 10, हिंसु 2 P, व्यव-कल् 10 (कलयति); विशुध् 10, (with instr.); शुध् c.: एतान्युतानि ... (Li. 13) 'these s. ed from 10,000;' अयुत-... शोधिते जातं &c. (*ibid.*). 2 उद्-हृ 1 P. **-ion,** *s.* वियोजनं, वियोगः, व्यवकलितं, व्यवकलनं, शोधनं, वि-,वर्जनं. 2 उद्धारः. **-Subtrahend,** *s.* ऋणं, शोधकः.

Suburb, *s.* (नगर-) परिसरः, उपकंठं, पर्यंत-भूमि *f.*, उपशल्यं, उपांतं, शाखानगरं, उपनगरं. **-an,** *a.* नगरोपांतस्थ-वर्तिन्, उपकंठ.

Subvert, *v. t.* उद्-,ध्वंस् c.. उन्मूल् 10, विनश् c., उच्छिद् 7 P or c., अपसृ c, खंड् 10, नि-अव-पत् c. **-Subversion,** *s.* ध्वंसः, उच्छेदः, वि-,नाशः, &c. **-Subversive,** *a.* विनाशिन्, ध्वंस-नाश-कर (री *f.*), उच्छेदिन्; better ex. by (*v.*); 'it is s. of happiness' सुखं उच्छिनत्ति, सुखांत-करं

Subway, *s.* आंतर्भौममार्गः.

Succeed, *v. i.* (Of things) निष्पद् 1 A, सं-पद्, सफलीभू 1 P; फल् 1 P; सिध् c. (साधयति), अर्थं आप् 5 P, विजयिन्-*a.* भू (of persons); सिध् 4 P (of both); 'he s. ed in all his attempts' सर्वे तस्य प्रयत्ना निष्पन्नाः-सफला बभूवुः &c. **-v. t.** Ex. by Go q. v. with (अनंतरं with abl.) पश्चात् (with gen.); अनु pr.; 's. ing his father as sovereign of the North Kosala' पितुरनंतरमुत्तरकोशलान्समधि-गम्य (R. ix. 1); 's. to the throne' राजपदं-सिंहासनं-आरुह् 1 P, राजपदं आप् 5 P, राजपदमाप् भू; 's.-ed his brother' भ्रातुः पश्चात् राज्यमवाप; 's. ed the General' सेनापतेः पश्चात् तत्पदमवाप,(lit.) सेनापतिमन्वभवत्; *See* **Follow;** 'joy s.-ed by fear' भयोत्तरः हर्षः. **-ing,** *a.* पर, उत्तर, आगामिन्, अनुयायिन्-गामिन्, 's. generations' पुत्रपौत्रादयः, उत्तर-कालीना जनाः. **-Success,** *s.* सिद्धि *f.*, साफल्यं, अर्थ-साध्य-सिद्धिः, कृतार्थता, जयः, संपद् *f.*, श्रीः, उदयः. **-ful,** *a.* कृतिन्, कृतार्थ, सिद्धार्थ, विजयिन्, चरितार्थ, कृत-कृत्य, प्राप्त-पूर्ण-लब्ध-काम, संपन्नमनोरथ. 2 (Of things) सिद्ध, सफल, निष्पन्न, फल-वत्. **-fully,** *adv.* सफलं, अद्धा, अमोघं, सिद्ध्या. **-ion,** *s.* अनु-,क्रमः,परंपरा, आनु-पूर्व्यं, पर्यायः, अन्वयः, श्रेणी; *See* **Order;** 'in s.' अनुक्रमं-क्रमेण, यथाक्रमं, अनु-पूर्वशः, निरंतरास्वंतरवातवृष्टिषु (K. v. 25) 'coming in s.'. 2 श्रेणी, आवलि-ली *f.*, माला; *See* **Series.** 3 उत्तराधिकारः-रिता, दायाधिकारः. **-ive,** *a.* क्रमबद्ध, आनुक्रमिक (की *f.*), यथाक्रम, अनु-पूर्व, परंपरा or क्रम-आगत or आयात,क्रमानु-सारिन् 2 निरंतर, सतत, अविरत. **-ively,** *adv.* क्रमशः, क्रमेण, अनुक्रमशः, अनुपूर्वशः, आनुपूर्व्येण, यथाक्रमं. **-or,** *s.* प्रत्यनंतरः, उत्तराधिकारिन् *m.*, अनंतरगामी.

Succinct, *a.* संक्षिप्त, लघु, अविस्तीर्ण. **-ly,** *adv.* संक्षिप्तं, समासतः.

Succour, *s.* साहाय्यं, शरणं. **-v. t.** दा 3 U with (*s.*), उपकृ 8 U.

Succulent, *a.* सरस, आर्द्र, रसमय (यी *f.*), सद्रव, सजल.

Succumb, *v. i.* वशं गम् 1 P or इ-या 2 P, वशीभू 1 P, अव-,सद् 1 P: *See* 'Give way' under **Give.**

Such, *a.* ईदृश्-श (शी *f.*), तादृश्-श, एता-दृश्-श, तथाविध, एवंविध; 's. as myself, -yourself' मादृश्-श, मद्विध, भवादृश्-श, त्वादृश &c.; 's. and s.' अमुक; 'as s.' एवं सति; परमार्थतः प्रेम 'affection as s.'

Suck, *v. t.* आ-,चूष् 1 P, पा 1 P. 2 (As children) धे 1 P, स्तनं-स्तन्यं-पा; 'a child that s.-s the breast' स्तनंधयः शिशुः. 3 (up) उत्-, शुष् c., आ-नि-पा, आचम् 1 P, (रसं) आदा 3 A. **-ing,** *s.* स्तनपानं, चूषणं. 2 स्तन्यं, दुग्धं, चूष्यं; 'who gives s.' स्तन्यदायिनी. **-Suckle,** *v. t.* स्तनं-स्तन्यं पा c. or दा 3 U, स्तनं धे c. (धापयति), स्तन्यदानेन पुष् c. **-ing,** *s.* स्तन्यदानं. 2 स्तनंधयः (यी *f.*), स्तन्य-पायिन्. **-Suction,** *s.* आ-,चूषणं.

Sudden, *a.* आकस्मिक (की *f.*), अतर्कित, अलक्षित, अतर्कित-अचिंतित-पूर्व, अकल्पित, अकस्मात्कृत. 2 चल, चंचल, लोल, *See* **Fickle. -ly,** 'on a s.' *adv.* अकस्मात्, सहसा, एकपदे, अकांडे, काकतालीय-

न्यायेन, अतर्कितं, असमर्थितं; 'befalling s.' असमर्थितोपगत.

Sudorific, *a.* स्वेदजनक (-नी *f.*), स्वेदकर (-री *f.*).

Sue, *v.* प्र-अभि-अर्थ् 10 A, कथयते याच् 1 A. 2 अभियुज् 7 A, 10, लिखिष् c. (राजकुले); 'if he s. me in a court of law' यद्यसौ राजकुले मां कथयति (Mr. 4)

Suet, *s.* वसा, मेदस् *n.*

Suffer, *v. t.* अनुभू 1 P, उपलभ् 1 P, उप-, भुज् 7 A, भार् 5 P, ज्ञा 9 U (Experience, q. v.). 2 अनु-ज्ञा, अनुमन् 4 A, अनुबुध् 1 A, न प्रतिबंध् 9 P or प्रतिषिध् 1 P. 3 तिः-, सह् 1 A, क्षम् 1 A, मृष् 4 P, 10. —*v. i.* (from) क्लिश्-तप्-पीड्-pass., व्यथ् 1 A; 'is s. ing from an injury' (क्षत-) निकृत्या पीड्यते; ex. by भाज् in comp., (दुःखभाक्); दुःखं-पीडां-अनुभू; परार्थे यः पीडामनुभवति 'who s. s for others'; 'if any important duty should not s. thereby' यदि नावसीदति गुरु प्रयोजनं (Ka. 181) 'a wicked person commits a fault and a good man s. s for it' खलः करोति दुर्वृत्तं नूनं फलति साधुषु. —ance, *s.* अनुज्ञा, अनुमति *f.*, क्षमा. —er, *s.* दुःखितः, दुःखभाक्, दुःखी. —ing, *s.* पीडा, क्लेशः, दुःखं, व्यथा, परि-,सं-,तापः, वेदना, कृच्छ्रं. 2 दुःखानुभवः-वेदनं &c.—*a.* क्लिष्ट, दुःखभाक्-भागिन्.

Suffice, *v. i.* कल्प् 1 A (with dat.), पर्याप्त-*a.* भू 1 P; *See* below; 's. it to say' इति कथनं पर्याप्तं भवतु. —**Sufficient,** *a.* पर्याप्त, उपयुक्त, उचित, समर्थ, gen. by अलं (with dat.). 'this (cow) will be s. to satisfy my hunger' तस्यालमेषा क्षुधितस्य तृप्त्यै (R. ii. 39), क्षुधाशांतये कल्पेत, पर्याप्ता भवेत्. 2 यथेष्ट, प्रचुर, विपुल; 'you cannot do him s. honour' तद्विषये अपर्याप्तिर्बहुमानस्य. —ly, *adv.* पर्याप्तं, यथेष्टं, प्रचुरं. —**Sufficiency,** *s.* पर्याप्ति *f.*, औचित्यं, यथेष्टता. 2 स्वशक्त्यभिमानः.

Suffix, *See* **Affix.**

Suffocate, *v. t.* श्वासं-कंठं-रुध् 7 U or स्तंभ 9 P; *See* **Choke.**—ed, *a.* रुद्धश्वास-प्राणकंठ. —ion, *s.* श्वास-प्राण-रोधः, कंठस्तंभनं.

Suffrage, *s.* *See* **Vote.**

Suffuse, *v. t.* आ-परि-प्लु c., व्याप् 5 P, व्यश् 5 A, आ-सं-कॄ 6 P; 'eyes s. ed with tears' बाष्पपरिप्लुत-अश्रुप्लावित-बाष्पसमाकुल-नयने; 's. ed with blushes' व्रीडापरिगत, सव्रीड, व्रीडाविलक्ष. —ion, *s.* आप्लावः-वनं, व्यापनं.

Sugar, *s.* शर्करा, सिता, खंडविकारः; 'coarse s.' गुडः; 'raw s.' मत्स्यंडी, फाणितं. —*v. t.* मिष्टी-मधुरी-कृ 8 U, शर्करान्वित-*a.* कृ. —ed,-y, *a.* मधुमय (-यी *f.*), मधुस्यंदिन्, शर्करावगुंठित, सशर्कर, मिष्ट, शर्करायुक्त; 's.-candy' सितखंडः, खंडमोदकः; 's.-cane' इक्षुः, रसालः.

Suggest, *v. t.* सूच् 10, उपन्यस् 4 U, उपक्षिप् 6 P, अभिदिश् 6 P, प्रस्तु c., सद्युप-स्था c. (स्थापयति), व्यंज् c. 2 उपदिश्, प्रबुध् c., मंत्र् 10 A; 's. ed sense' व्यंग्यः-ध्वन्यः-अर्थः; 'such is the s. ed sense' इति व्यंग्यः; 'this plan s. ed itself to my mind' अयमुपायो मे मनसि प्रादुर्बभूव, एनमुपायमहमचिंतयम्. —ion, *s.* सूचना, उपन्यासः, उपक्षेपः,प्रस्तावः. 2 मंत्रणं,उपदेशः, बुद्धि *f.* —ive, *a.* व्यंजक, सूचक, प्र-,बोधक.

Suicide, *s.* आत्महत्या-घातः-वधः, प्राणजीवित-त्यागः. हिंसा. 2 आत्मघातकः-घातिन् *m.*; 'commit s.' प्राणान् उत्सृज् 6 P, आत्महत्यां कृ. —al, *a.* आत्मघातिन्, आत्मघातिन्, स्वनाशक.

Suit, *v.* युज् pass. (with loc. of person), रुच् 1 A (with gen. of person), उपपद् 4 A, (with gen. or loc); मह् सम्यग् इत्येव मां प्रत्युपयाति शोभते तातपरिजनस्य (U. 1); गुणवत्त्वं गुणात्मनो शोभते, मे गुणाः परिवर्तन्ते मह्यानि उपपद्यते (S. B. 147, 170), oft. ex. by words for 'proper' q. v. —*s.* प्रार्थना, प्रणयः, विज्ञप्ति *f.*, विज्ञापना. 2 कार्य, अभियोगः, व्यवहारः, अर्थः; 'file a s.' अभियुज् 7 A; *See* **Sue.** 3 (Of clothes &c.) युगलं, युग्मं, युतकं, युग्मं, संयोगः, समूहः; *See* **Set.** 4 परिजनः, परिवारः, *See* **Retinue.** —able, *a.* अनुरूप, युक्त, उचित, योग्य, उपपन्न, अनुगुण, सदृश (-शी *f.*); *See* **Becoming,** **Proper** —ably, *adv.* यथोचितं, अनुरूपं, यथायोग्यं, यथार्ह, युक्तं. 2 अनुगुणं अनुसारेण, अनुरोधेन. —or, *s.* प्रार्थयितृ *m.*, याचकः; आवेदकः. 2 अर्थिन् *m.* 3 विवाहार्थिन् *m.*, पाणिग्रहणार्थिन् *m.*

Suite, *s.* परिच्छदः, परिवारः, परिजनगणः. 2 (Of rooms) समष्टि *f.*, संयोगः.

Sulk, *v. i.* उद्-आस् 2 A, उद्-विज् 7 P. —y, *a.* रुष्ट, प्रतीप, विषण्ण, उदासीन, उद्विग्न, अंतःकुपित. —ily, *adv.* उदासीनवत्, सोद्वेगं. —iness, *s.* औदासीन्यं, अंतःकोपः, उद्वेगः.

Sullen, -ly, -ness, *See* **Sulky,** -ly, -ness.

Sully, *v. t.* दुष् c. (दूषयति), आविलयति कलंकयति (D.), मलिनीकृ 8 U; *See* **Stain.**

Sulphate, *s.* (Of copper) तुत्थं, 'red s. of iron' कासी(-सी)सं; 'green s. of iron' धातुशेखरः

Sulphur, *s.* गंधिकः, गंधकः, गंधाश्मन् *m.*, सौगंधिकः. **-ated, -eous**, *a* गंधकसंपृक्त-युक्त गंधकगुणविशिष्ट, गंधकगर्भ.

Sulphuret, *s.* (Of iron) ताप्यं; (of mercury) कज्जली.

Sultry, *a.* प्रखर, तिग्म, प्रवृद्धताप, अत्युष्ण, निर्वात; 's. season' निदाघः, ग्रीष्मः.

Sum, *s.* योगः, संकलनं, संयोजनं (in Math.). 2 साकल्यं, समाहारः. समवायः. 3 सारः. तात्पर्यं, सारांशः. 4 राशिः. 5 संग्रहः, संक्षेपः. 6 (Of money) राशिः. धनभागः-अंशः. oft. not ex.; 'spending a large s. of money' भूरिद्रव्यव्ययः; 'small s. of money' अल्पधनं, बहुधनं &c. 7 परा कोटिः, सारः; 's. and substance': *See* **Substance**. —*v. t.* संयुज् 10, सं-कल् 10 (कलयति). 2 (up) संक्षेपेण कथ् 10, समासतो वद् 1 P, (उक्तं) उपसं-हृ 1 P. —**Summary**, *a.* संक्षिप्त, सामासिक (की *f.*). 2 क्षिप्र, अविलंबित —*s.* संक्षेपः, सारः, संग्रहः. —**ly**, *adv.* संक्षेपतः, संक्षेपेण, समासतः.

Summer, *s.* ग्रीष्मः, निदाघः, घर्मः, तपः, उष्णः, उ(ऊ)ष्मागमः, उ(ऊ)ष्मकः, ग्रीष्मसमयः-कालः &c.; 's.-house' केलि or विलास-गृहं or मंदिरं; 's.-house with fountains &c.' जलमंदिरं, धारायंत्रगृहं.

Summit, *s.* शिखरः-रं, शृंगं, सानु *m.*, *n.*, चूडा, शिखा, अग्रं कूटः-टं; 'reclining on the s. of the western mountain' अस्ताचलचूडावलंबिन्. 2 (fig.) परा काष्ठा-कोटिः.

Summon, *v. t.* आह्वे 1 P, आकृ c., आनी c., आवह् c.; 'to s. up courage'; *See* **Courage**. —**Summons**, *s.* आह्वानं; 'written s.' आह्वानपत्रं; 'he who disobeys a s.' आहूतोऽनागच्छन् (V. M. 4).

Summum-bonum, *s.* निःश्रेयसं, परमार्थः, अपवर्गः.

Sumpter, -horse, *s.* रह्(स्थौ)रिन् *m.*, पृष्ठ्यः.

Sumptuary, *a.* व्ययविषयक, व्ययनियम-संबंधिन्.

Sumptuous, *a.* महार्ह-र्घ, बहुव्ययसाध्य, महा-बहु-मूल्य. 2 विशिष्ट; 's. feast' भोजनविशेषः. —**ly**, *adv.* अतिव्ययपूर्वं, महाव्ययेन. —**ness**, *s.* महा-अति-व्ययः.

Sun, *s.* रविः, सूर्यः, आदित्यः, भानुः, सवितृ, अर्कः, भास्करः, दिनकरः, दिवाकरः, मार्तंडः, मरीचिन्, विवस्वत्, मित्रः, तपनः, पूषन्, भास्वत्, and comp. of 'Hot' with 'Ray', 'Ray' with सहस्र, पतिः with 'Day'; उष्णरश्मिः, सहस्रकिरणः, सहस्रभानुः, दिनपतिः &c. 2 आतपः; 'morning s.' बालातपः, बालार्कः; 'exposed to the sun' आतपे न्यस्तं, आतपायोज्झितं (धान्यं); 's.-beam' सूर्यकिरणः, अंशुः; *See* **Ray**; 's.-day' रविवारः-वासरः, भानुवासरः; 's.-dial' सूर्यघटी; 's.-rise' सूर्योदयः, उदयः; 's.-set' अस्तगमनं, अस्तः, दिनांतः; 'at s.-set' अस्तं गते रवौ; 'at s.-rise'; समुदिते रवौ 'from, s.-stroke' आतपलंघनात् (*S.* 3); 's.-shine' सूर्यातपः, प्रकाशः, सूर्यालोकः. —**ny**, *a.* सौर (री *f.*) (*s*) in comp. 2 सूर्यतप्त, आतपव्याप्त, आतपाक्रांत, आतपवत्, सातप.

Sunder, *See* **Separate**.

Sundry, *a.* बहुविध, नानाविध, विविध, अनेक-नाना in comp.

Sup, *v. i.* रात्रौ भुज् 7 A. —**Supper**, *s.* रात्रिभोजनं.

Super, A prefix rendered by अति, अधिक, अतिशय in comp.; 's.-abound' अतिबहुलीभू; 's.-abundant' अतिबहुल, उपचित.

Super-annuated, *a.* वयोऽधिक, वार्धक्येन कार्याक्षम.

Superb, *a.* अतिशोभन; *See* **Magnificent**.

Supercilious, *a.* अवलिप्त, अहंकारिन्, अतिदृप्त.

Supererogatory, *a.* विध्यतिरिक्त, नियमातिरिक्त. —**Supererogation**, *a.* नियमातिरेकः, अत्याचारः.

Superficies, *s.* तलं, पृष्ठं. —**Superficial**, *a.* बाह्य, बहिःस्थ, बहिः-पृष्ठ in comp.; 's. contents' पृष्ठफलं; 's. view' बाह्यालोकः. 2 अगाध, पल्लवग्राहिन्, अल्प, असूक्ष्म, अनिपुण, अगाढ; 's. scholar' अल्पज्ञः, पुंश्चलः. —**ly**, *adv.* बाह्यतः, बहिः.

Superfine, अतिसूक्ष्म, सर्वोत्कृष्ट.

Superfluous, *a.* अधिक, अतिरिक्त, व्यर्थ, अपेक्षातिरिक्त; oft. ex. by. पुनरुक्त; 'render s.' पुनरुक्ततां नी 1 P, (इदमुत्थाय सरःसलिलं अमृतरसमुत्पादयता पुनरुक्ताभिव नीता स्वसृष्टिः Ks. 124); 'when there is clear moonlight, torches are s.' अभिव्यक्तायां चंद्रिकायां किं दीपिकापौनरुक्त्येन (V. 3); आज्ञाक्यमल्पपुनरुक्तभूतं (R. v. 34). —**ness**, -**Superfluity**, *s.* आधिक्यं, पुनरुक्तता, अतिरेकः, वैयर्थ्यं.

Superhuman, *a.* अ-अति-मानुष (षी *f.*), अतिमर्त्य, अपौरुष (षी *f.*). मानुषातिग.

Superincumbent, *a.* उपरिस्थित, अधिशयान, उपरिवर्तिन्.

Superinduce, *v. t.* अभ्यावह् c., अधिनिविश् c.

Superintend, *v. t.* पर्यवेक्ष् 1 A, अधि-ष्ठा 1 P, अध्यास् 2 A. —**ence**, *s.* अधिष्ठानं, अवेक्षा, अधिकारः, अध्यक्षता, अवेक्षणं, कार्यदर्शनं. —**ent**, *s.* पर्यवेक्षकः, अधीशः, अध्यक्षः, अधिकारिन् *m.*

Superior, *a.* (To) ज्यायस्, गरीयस्, श्रेयस्, वरीयस्; अधिक, श्रेष्ठ, वरिष्ठ, गरिष्ठ, विशिष्ट, प्रमुख; oft. by अतिरिच्-विशिष् pass.; *See* **Excel**; ' truth is s. to thousands of horse-sacrifices ' अश्वमेधसहस्रेभ्यः सत्यमेवातिरिच्यते-विशिष्यते (H. 4); ' of s. merits ' गुणाधिक, विशिष्टगुण. –*s.* गुरुः, ज्येष्ठः, श्रेष्ठः, वरिष्ठः, अध्यक्षः –**ity,** *s.* आधिक्यं, ज्येष्ठता, श्रेष्ठता, विशिष्टता, उत्कर्षः, प्राबल्यं, प्राग्भावः.

Superlative, *a.* सर्वोत्कृष्ट; परम, अत्युत्तम, अतिशय in comp. –**ly,** *adv.* अत्यंतं, परमं.

Supernatural, *a.* अलौकिक (की *f.*), अअति-मानुष- (षी *f.*), प्रकृतिबाह्य, मानुषातिग. –**ly,** *adv.* अलौकिकतया.

Supernumerary, *a.* अतिरिक्त; अधिक, संख्यातिरिक्त.

Superpose, *v. t.* उपरि नि-धा 3 U.

Superscribe, *v. t.* बाह्यनाम लिख् 6 P or दा 3 U. –**Superscription,** *s.* बाह्यनाम; (fig.) बहिर्देशः, बाह्यभागः.

Supersede, *v. t.* उल्लंघ् 1 A, 10, अतिक्रम् 1 U, 4 P, निरस् 4 U, निराकृ 8 U; ' s. ed him in the office ' तमतिक्रम्य तत्पदमवाप: **2** वि-,लुप् c., खंड् 10, निवृत् c. –**ed,** *a.* निरस्त, विलोपित; ' a s. wife ' अधिविन्ना, अध्यूढा.

Superstition, *s.* मूढविश्वासः, अतिविश्वासः-भक्ति *f.*, मिथ्याधर्मः; अविधिनिष्ठा-श्रद्धा. –**Superstitious,** *a.* मूढ, विश्वासनिष्ठ; असत्य-मिथ्या-धर्मिन्, अत्याचारनिष्ठ. **2** मूढविश्वासमूलक.

Superstructure, *s.* भवनं, मंदिरं; *See* **Building.**

Supervene, *v. i.* अकस्मात् उप-स्था 1 P, or उपगम् 1 P.

Supervise, *v. t.* पर्यवेक्ष् 1 A. –**er,** *s.* पर्यवेक्षकः; *See* **Superintend.**

Supine, *a.* उत्तानशय, अधपृष्ठशायिन्, उत्तान, ऊर्ध्वमुख (खी *f.*). **2** अलस, निरीह, उदासीन. –**ness,** *s.* आलस्यं, तंद्रा.

Supplant *v. t.* निष्कस् c., स्थानं स्थाप् 5 P or अधि-ष्ठा 1 P, अंध-निः-सृ c., निराकृ 9 U, निरस् 4 U.

Supple, *a.* कोमल, सुनम्य, अदृढ, मृदु, चपल, लघु, नमनशील

Supplement, *s.* परिशिष्टं, परिपूरणं, उत्तरखंडः, शेषपूरणं. –*v. t.* पूर् 10, न्यूनतां निराकृ 8 U –**al, –ary,** *a.* परिशिष्ट in comp.

Suppliant, Supplicant, *s.* अर्थिन् *m.*, प्रणयिन्, प्रार्थकः, शरणागतः; ' service to s. s ' प्रणयिक्रिया. –*a.* प्रणत, नम्र, कृतांजलि, बद्धांजलि, शरणार्थिन्. –**ly,** *adv.* सानुनयं.

Supplicate, *v. t.* अनु-नी 1 P, अर्थ् 10 A, सांजलि याच् 1 A. –**ion,** *s.* प्रार्थना-नं, अनुनयः, सविनयप्रार्थना. –**ory,** *a.* सानुनय, सविनय, प्रणतिपूर्व.

Supply, *v. t.* उपाहृ 1 P, परि-उप-क्लृप् c., संयुज् 10; ' he was s. ed with food ' अन्नमुपकल्पितं तस्य; सं-भृ 3 U, उप-स्था c. (स्थापयति), परि-,पूर् 10. **2** (An ellipsis.) अध्याहृ, अभ्यूह् 1 U, पूर्. –*s.* संभारः, संचयः, सामग्री, उपकल्पनं. **2** (S. s) वीवधः; *See* **Provision.**

Support, *v. t.* उप-सं-अव-उत्-स्तंभ् 9 P or c., आ-अव-लंब् 1 A, सं-,भृ 1 P, 10, आलंबं-अवलंबं-धा 3 U; ' how shall I s. my life ' कथं जीवितं धारयिष्यामि (S. 4); ' s. by the hand' हस्तं दा, (सेवाविचक्षणहरीश्वरदत्तहस्तः R. xiii. 69); *See* **Lean. 2** भृ 1, 3 U, ग्रासाच्छादनं दा 3 U, पुष् 1, 9 P or c., (अन्नादिना) पा c. (पालयति), संवृध् c.; 's. oneself' उदरपूरणं कृ. **3** वि-,सह् 1 A: *See* **Bear. 4** उपकृ 8 U, अनुग्रह् 9 P, साहाय्यं कृ. **5** समर्थ् 10, दृढयति (D.); *See* **Prove;** न ह्ययं मंत्रः स्वातंत्र्येण कंचिदपि वादं समर्थयितुमुत्सहते (S. B. 356) ' cannot, by itself, s. any theory '. **6** अभिनंद् 1 P, अनुमुद् 1 A, अनुकूलयति (D.). –*s.* आ-अव-लंबः-लंबनं, धारणं; ' s. of life' असुधारणं, प्राणयात्रा. **2** अवष्टंभः, आश्रयः, आधारः, आ-अवलंबः, उपस्तंभः, उपघ्नः; ' a tree of s. ' संश्रय-आश्रय-द्रुमः, उपघ्नतरुः. **3** भरणं, पोषणं, पालनं, संवर्धनं. **4** (Means) आजीवः; उपजीविका; *See* **Living. 5** साहाय्यं, अनुग्रहः, आनुकूल्यं, अभिनंदनं. –**ed,** *a.* साधार, सावष्टंभ, उत्तंभित, दत्तहस्त (with the hand). **2** सप्रमाण. –**er,** *s.* आधारः, अवष्टंभः, आलंबिन् *m.*, उद्वहः. **2** पोषकः, वर्धयितृ *m.*, पालकः.

Suppose, *v. t.* वि-सं-भू c., क्लृप् c., उपन्यस् 4 U. **2** मन् 4 A, ऊह् 1 A, अनु-ज्ञा 9 A, अवगम् 1 P, वि-,तर्क् 10; *See* **Infer;** ' s. ing that ' ex. by अथ, यदि, (अथ मरणमवश्यमेव जंतोः Ve. 3). –**ition,** *s.* सं-, भावना, कल्पना, उपन्यासः; तर्कः, ऊहः, अनुमानं; ' on this s. only ' एवं कल्पित एव, अनेन एव उपन्यासेन. –**Supposititious,** *a.* कूट in comp., कृत्रिम, कल्पित; ' s. child ' पुत्रप्रतिनिधिः, कूटपुत्रः.

Suppress, *v. t.* सं-नि-यम् 1 P, निग्रह् 9 P, अव-सं-नि-रुध् 7 U, नि-वृ c., निबंह् 10; वृ 10. स्तंभ् 9 P or c., प्र-,शम् c. (शमयति), निवृत् c.; ' s. ing the emotions of sorrow ' निगृह्य शोकावेगं; अंतर् in comp.; ' who s. es his tears' [illegible]

रणं; (the passions) जि 1 P, दम् c. (दमयति), नि-सं-यम्, निग्रह्; *See* **Control.** **2** गुह् 1 U, छद् 10, गुप् 1 P, संवृ 5 U, अपलप् 1 P; *See* **Conceal.** **-ion,** *s.* सं-नि-यमः-मनं, निग्रहः, अव-निरोधः, नियंत्रणं, स्तंभनं, निवारणं, प्र-,शमनं, अवष्टंभः; (of the passions) दमः-मनं, जयः, निग्रहः, &c. **2** गूहनं, गोपनं, छादनं.

Suppurate, *v. i.* पाकं व्रज् 1 P, पच् pass., सपूय-*a.* भू. **-ion,** *s.* परि-,पाकः, सपूयत्वं.

Supreme, *s.* परम, अतिश्रेष्ठ, निरतिशय; 's. soul' परमात्मा, परब्रह्म, जगदात्मा. **2** मुख्य, प्रभविष्णु, प्रधान, विशिष्ट; *See* **Principal;** 's. power' साम्राज्यं, पारमेष्ठ्यं, प्रधानाधिकारः, ऐकपत्यं; 's. monarch' अधीश्वरः, सम्राट्, परमराजः; 'be s. to' अति-रिच्-विशिष्-pass., (with abl.); *See* **Excel. -ly,** *adv.* परमं, अत्यंतं, परं, अति-सु pr. **-Supremacy,** *s.* आधिपत्यं, प्रभुत्वं, प्रभविष्णुता, स्वाम्यं, प्राधान्यं, मुख्यता, श्रेष्ठता, विशिष्टता.

Surcharge, *v. t.* अत्यंतं पूर् 10. **-ed,** *a.* अतिभाराक्रांत, पूर्णगर्भ.

Surd, *s.* करणी.

Sure, *a.* निश्चित, असंदिग्ध, ध्रुव, निःसंशय, स्थिर, नियत; *See* **Certain;** (of persons) दृढविश्वास, जातप्रत्यय, संशयहीन; 'I am s.' दृढं मन्ये, मम दृढप्रत्ययाशा विद्यते, नूनं खलु, or एव with verbs; 'he is s. of success' सिद्धिं ध्रुवां मन्यते; 'she is s. of heaven' तस्याः स्वर्गवासोऽवस्थित एव; तं हतं विद्धि 'be s. that he will be killed'. **3** निर्भय; अकुतोभय; *See* **Secure, Safe. -ly,** *adv.* नियतं, नूनं, खलु, ध्रुवं, अवश्यं, निश्चितं, निःसंदेहं, निःसंशयं; *See* **Certainly. -ty,** *s.* प्रतिभूः, बंधकः, लग्नकः; 's. for recognizance' दर्शनप्रतिभूः. **2** प्रत्ययः, निर्णयः, निश्चयः. **-tyship,** *s.* प्रातिभाव्यं.

Surf, *s.* लहरी, तरंगः, कल्लोलः.

Surface, *s.* तलं, पृष्ठं, मुखं, दृश्यांगं, तल-पृष्ठ-भागः, पीठं; 's. of the earth' क्षितितलं, धरापीठं &c.

Surfeit, *v. t.* अतिपूर् 10, अतिभोजनं कृ c., अत्यंतं तृप् c., सौहित्यं-निर्वेदं-जन् c.; *See* **Glut.** **-s.** अतिभोजनं, अतिपूरणं, अतितृप्ति *f*-सौहित्यं.

Surge, *v. i.* उच्छल् 1 P, उद्भ्रम् 1 P, उत्क्षिप् pass.; 's. ing waters' कल्लोलाकुलं-तरंग-क्षुभितं-जलं **-s.** कल्लोलः, महोर्मि *f*.

Surgeon, *s.* शल्यतंत्रविद्, शस्त्रवैद्यः. **-Surgery,** *s.* शल्यं, शल्यतंत्र-शास्त्रं, शस्त्रविद्या. **-Surgical.** *a.* (*s.*) in comp.

Surly, *a.* कर्कश, रूक्ष, परुष, प्रतीप, वक्र, दुःशील.

Surmise, *v.* आ-,शंक् 1 A, तर्क् 10, सं-भू c. **-s.** वि-,तर्कः, आ-,शंका.

Surmount, *v. t.* तॄ 1 P, सं-उत्-,° अतिक्रम् 1 U, 4 P, लंघ् 1 A, 10, पारं गम् 1 P.

Surname, *s.* उपनामन् *n.*, कुलनाम. **-v. t.** Ex. by (*s.*); 's. ed Vyasa' व्यासइत्युपाख्यः, व्यासोपनामा.

Surpass, *v. t.* अति-शी 2 A, अतिक्रम् 1 U, 4 P, अतिरिच्-विशिष्-pass., जि 1 P; *See* **Excel. -ing,** *a.* अति in comp.; 's. the strength of man' अतिमानुष; *See* **Beyond.**

Surplice, *s.* धौतावारः, उपरिच्छदः.

Surplus, *s.* उद्-वृत्तं, उद्वर्तः, अतिरिक्तभागः.

Surprise, *v. t.* वि-स्मि c. (स्माययति, स्मापयते), साश्चर्य-*a.* कृ, विस्मयेन उपहन् 2 P, विस्मयाकुल-आश्चर्यचकित-*a.* कृ. **2** अतर्कितसहसा-आपत् 1 P or आसद् c. or अवस्कंद् 1 P; सन्निपत्याभियुक्तः (U. 3) 'was s. ed and attacked.' **-s.,-al,** *s.* विस्मयः, आश्चर्यं, चमत्कारः, चमत्कृति *f.*, अद्भुतं. **2** अतर्कितः आपातः-अवस्कंदः, सहसाक्रमः-अवस्कंदनं. **-ed,** *a.* विस्मित, विस्मापित, विस्मयाकुल, साश्चर्य, आश्चर्यचकित, विस्मयोपहत-अन्वित-आपन्न; 'to be s.' विस्मि 1 A. **2** सहसाक्रांत. **-ing,** *a.* आश्चर्य-विस्मय-कर (री *f.*), अद्भुत, चित्र, आश्चर्य-विस्मयावह.

Surrender, *v. t.* उपा-हृ 1 P, उपा-नी 1 P, सं-,ऋ c. (अर्पयति), निक्षिप् 6 P, प्र-दा 3 U, प्रति-पद् c. **2** परि-,त्यज् 1 P, उत्सृज् 6 P, हा 3 P, संन्यस् 4 U. **3** (Oneself) शरणं गम् 1 P or या 2 P or प्र-पद् 4 A, वशं गम्-या. **-s.** समर्पणं, प्रदानं, परि-,त्यागः, उत्सर्गः. **2** प्रणति *f.*, वशगमनं.

Surreptitious, *a.* मोषेण-चौर्येण-छलेन-कृत-प्रकाशित-निवेशित, &c. **-ly,** *adv.* छलेन, सकपटं.

Surround, *v. t.* परि-वृ 5 U or c., परिक्षिप् 6 P, परि-इ 2 P, परिगम् 1 P, परि-,वेष्ट् 1 A or c., परि-स्तृ 1 P; oft. by मेखला, रसना, वलय in comp.; 'the earth s. ed by ocean' समुद्ररसना-उदधिवलया-रत्नाकरमेखला-उर्वी. **-ing,** *a.* समंततः वर्तिन्, आभोग-पर्यंत-वर्तिन्; परिसरस्थ; *See* **Near. -s.** परिवेष्टनं, संवलनं.

Surtout, *s.* उत्तरीयं, प्रावारः.

Surveillance, *s.* अवेक्षा-क्षणं, निरूपणं.

Survey, *v. t.* प्र-,परि-,मा 3 A or c. (मापयति). **2** (With the eye) संदृश् 1 P, परि-अव-ईक्ष् 1 A, विलोक् 1 A,10, निरीक्ष्, निरूप् 10. **-s.** अव-आ-लोकः-कनं, निरीक्षा, निरीक्षणं. **2** मापनं. **-or,** *s.* क्षेत्र-भू-मापकः.

Survive, *v. t.* अति-जीव् 1 P; जीव् with पश्चात् (with gen.) or उत्तरं (with

abl.); 's. danger' आपदं उह् 1 P. —v. i. वृ pass., अव-स्था 1 A. —al, s. अतिजीवनं, अवस्थानं. —ing, a., —or, s. शेष, अवशिष्ट, अतिजीविन्, म्रियमाण, अवस्थित.

Susceptible, a. योग्य, उचित, ग्राहिन्, ग्रहण-वेदन-क्षम-शक्त, गमनीय, ग्राहक; *See* **Admit** (of); 'I am made s. of an emotion' विकारस्य गमनीयास्मि संवृत्ता (S. 1); 'youth is s.' विकारि यौवनं (Mal 1); 's. of anger' सुलभकोप, क्रोधशील, क्षिप्रकोपिन्. —**Susceptibility**, s. ग्राहकत्वं, ग्रहण-वेदन-शीलता-क्षमता.

Suspect, v. t. शंक् 1 A, वि-आ-परि-°, सं-शी 2 A, न प्रति-इ 2 P or विश्वस् 2 P; 'excessive affection s. s evil' अतिस्नेहः पापशंकी (S. 4). 2 मन् 4 A, वि-, तर्क् 10. —**Suspicion**, s. आ-, शंका, संदेहः, संशयः, विकल्पः, वि-,तर्कः. —**Suspicious**, a. आ-,शंकिन्, आत्तशंक, शंका or संशय-शील or बुद्धि, साशंक, संदिग्धचित्त-मति, अविश्वासिन्. 2 आशंक्य, शंकावह, शंकास्थान-आस्पदं-पात्रं.

Suspend, v. t. उद्-,बंध् 9 P, प्र-अव-लंब् c., वि-अव-संज् c., विटपविषक्तवल्कलेषु (S. 1) 'the bark-garments s. ed from the branches', आंदोलयति (D.). 2 व्याक्षिप् 6 P, विलंब् c. 3 (From office) नियतकालं यावत् आधिकारात् निष्कस् c. or च्यु c. or भ्रंश् c. —ed, a उद्बद्ध, प्र-अव-लंबित, विषक्त, आंदोलित, &c.; 's. ed in a loop' काचित, शिक्यित; 's. ed from the neck' कंठलंबिन्-लग्न. —**Suspense**, s. अनिश्चयः, संदेहः, संशयः, विकल्पः, दोलावृत्ति f., द्वैधीभावः; भूतद्वैधीभावकातरं मे मनः (S. 1) 'my mind is held in s. and hence anxious', 'being in s.' दोलायमान, संशयदोलारूढ, संदेहदोलास्थ. —**Suspension**, s. उद्बंधनं, अवलंबनं. 2 विलंबनं, व्याक्षेपः. 3 विच्छेदः, निवृत्ति f., निरोधः.

Sustain, v. t. धृ 3 U, सं-वृध् c., पा c. (पालयति) &c. 2 स-,धृ 10, (शोकक्षोभे हृदयं प्रलापैरेव धार्यते U. 3); सं-स्तंभ् 9 P or c.; *See* **Support**; 's. life' प्राणधारणं-प्राणयात्रां-कृ 8 U, जीवितं धृ, प्राणसारं धृ; *See* **Live, Maintain**. 3 प्रवृत् c. 4 प्रति-उप-पद् c., *See* **Prove**. 5 सह् 1 A, अनु-भू 1 P. —**Sustenance**, s. जीवनं, उपजीविका, वृत्ति f., अन्नं, आहारः; *See* **Maintenance, Living**.

Sutler, s. सैन्यानुगामिन्-a. वणिज् m.

Suture, s. संधिः, सीवनं.

Suzerain, s. अधीशः, अधीश्वरः.

Swaddle, v. t. क्षौमेण परिवृ c. or परि-वेष्ट् c.; 's -ing clothes' बालपरिवेष्टनं.

Swagger, v. i. प्र-,गल्भ् 1 A, विकत्थ् 1 A; *See* **Boast**.

Swain, s. ग्रामिकः, असभ्यः, ग्रामीणः. 2 **Agriculturist**, q. v.

Swallow, v. t. ग्रस् 1 A, नि-, गॄ 6 P. —s. ग्रासः, निगलनं. 2 निगरणस्रोतस् n., अन्ननालिः; 's.-wort' अर्कः, वसु(सु)कः, आस्फोतः, गणरूपः, विक्षी(क्षि)रणः, मंदारः, अर्कपर्णः.

Swamp, s. कच्छभूः, अनूपो देशः, अनूपभूः. —v. t. आ-प्लु c.; *See* **Plunge**. —y, a. कच्छ, अनूप.

Swan, s. मरालः, राजहंसः, श्वेतगरुत् m.

Sward, s. शाड्वलं, सतृणभूमि f.

Swarm, s. संघः, समूहः, व्रजः, वृंदं, कुलं, *See* **Multitude**. —v. i. गणशः संनिपत् 1 P or संमिल् 6 P, संघशः गम् 1 P or या 2 P. —ing, a. (with) व्याप्त, संकुल, आ-सं-कीर्ण, जुष्ट, उपसेवित.

Swarthy, a. श्याम, कृष्ण, कृष्णवर्ण.

Swathe, s. पट्टः, दीर्घखंडः. —v. t. (पट्टेन) वेष्ट् 1 A or c., परिवृ c., परिच्छद् 10.

Sway, s. शासनं, आधिपत्यं, ईशत्वं, प्रभुत्वं, वशः-शो, अधीनता. —v. t. शास् 2 P. 2 प्रवृत् c., प्र-, नी 1 P, प्रेर् c., प्रयुज् 10, प्रणुद् 10; *See* **Influence, Subject**; 'not s. ed by avarice' अवशो लोभस्य, अनाकृष्टः लोभेन, लोभाप्रेरित, &c. —v. i. प्रेंख् 1 P, इतस्ततः चल् 1 P or कंप् 1 A, नम् 1 P, आ-प्र-लंब् 1 A.

Swear, v. i. शप् 1, 4 U, शपथं शप्. —v. t. शप् c., शपथं ग्रह् c. —er, s. शपथकृत् m. —ing, s. शपथं, शापः.

Sweat, v. i. प्र-,स्विद् 4 P; *See* **Perspire**. 2 परिश्रम् 4 P; तम् 4 P (tire). —v. t. स्विद् c. —s. स्वेदः, घर्मः, स्वेदजलं. 2 परिश्रमः, आयासः; 'by the s of thy brow' आत्मनः परिश्रमेण. —ing, —y, a. सस्वेद, घर्मलिप्त, स्वेदवत्.

Sweep, v. t. मृज् 2 P or c., सं-परि-प्र-°; 's. away' अप-अप-मृज्, अपवह् c., (वेगेन) अपनी; 's. across', 's. over' वेगेन अतिक्रम् 1 U, 4 P or अति-इ 2 P. —s. प्रसरः, गोचरः, विषयः; *See* **Range**. —er, s. संमार्जकः, खलपूः, बहुकरः. —ing, s. सं-,मार्जनं-ना, मलापहरणं. —ings, s. अवकरः, अव(प)स्करः, मलं, संकारः, उच्छिष्टं.

Sweet, a. मधुर; मिष्ट, सुरस, स्वादु, मधुमय (यी f.), (of taste only). 2 चारु, मंजुल, ललित, कोमल, मनोज्ञ; *See* **Pleasant**, 's. smile' चारु-मधुर-स्मितं; 's. song' चारुगीतं, c. —s. मधु n., मिष्टं, आस्वादः. 2 सुखं, सौख्यं; 's. s of royalty' राज्यसुखानि; 's.-heart' वल्लभ, प्रणयिन्, दयित कांत, रमण (णी f.), प्रियतम; 's.-meat

मिष्टान्नं, मोदकः, पायसं; 's.-smelling' सुगंधि, सुरभि; 's.-speaking, -toned, voiced' मंजुलस्वन, चाटुभाषिन्, प्रियंवद, मधुरवाक्. **-en,** *v. t.* मधुरीकृ 8 U, मिष्टीकृ स्वादूकृ. *-v. i.* मधुरीभू. **-ly,** *adv.* मधुरं, चारु, मधुर in comp.; 'smiling s.' चारुहासिन्. **-ness,** *s.* माधुर्यं, स्वादुता, &c.

Swell, *v. i.* श्वि 1 P or pass., प्र-उत्-°, स्फाय् 1 A, वृध् 1 A, उत्सृप् 1 P; प्र-उप-चि pass., बहुली-भू 1 P; 'a heart s. ing with joy' हर्षोत्फुल्लं हृदयं; *See* **Increase.** *-v. t.* श्वि c., स्फाय् c. (स्फावयति), वृध c. (with air), उद्-प्र-आ-ध्मा 1 P; *See* **Puff.** *-s.*, **-ing,** *s.* स्फीति *f.*, वृद्धि *f.*, उपचयः. **2** श्वयथुः; शोथः; शोफः, गंडः. **3** (Of the sea) ऊर्मिप्रलोठनं, संक्षोभः. **-ing,** *a.* श्वयमान, उत्सर्पिन्; 'a s. sea' प्रचलदूर्मिमालाकुल. **-Swollen,** *a.* शून, स्फीत, प्रवृद्ध, &c.

Swelter, *v. i.* घर्मेण अभिभू or बाध् pass.

Swerve, *v. i.* प्र-वि-चल् 1 P, भ्रंश् 4 P, 1 A, पराङ्मुखीभू 1 P, च्यु 1 A, व्यति-इ 2 P व्यतिक्रम् 1 U, 4 P, (with abl.); अपेसृ 1 P, अति-वृत् 1 A (with acc.): *See* **Deviate;** 's. ing from the right path' सन्मार्गभ्रष्ट, &c

Swift, *a.* जवन, वेगवत्, त्वरित, सत्वर, शीघ्र-द्रुत-लघु-गामिन्, प्र-,जविन्, शीघ्रग, प्रजवन, तरस्विन्, महावेग; 's. of foot' धावने महाजव; 'as s. as the wind' वायुगति, वायुवेग. **-ly,** *adv.* शीघ्रं, जवेन, सवेगं, सत्वरं. **-ness,** *s.* शीघ्रता, वेगः, तरस् *n.*

Swig, Swill, *v.* अतिपानं कृ 8 U.

Swim, *v. i.* तॄ 1 P; प्लु 1 A: 'swam across the sea with their arms' पयः अतारिषुर्भुजैः (Si. xii. 77): 's. ing against the waves' बाहुभ्यां लहरीर्भिन्दन्; 'the Earth s. s in blood' रुधिराप्लाविता मही. *-v. t.* तॄ (with acc.), पारं गम् 1 P. **-mer,** *s.* तरण-प्लवन-कृत् *m.* **-ming,** *s.* तरणं, प्लवनं; 's. against the current' प्रतीपतरणं.

Swindle,-er, *See* **Cheat.**

Swine, *s.* शू(सू)करः, वराहः. **-ish,** *a.* सौकर (री *f.*), सूकरशील-वृत्ति.

Swing, *s.* दोला-ली, प्रेंखा, प्रेंखोलनं, हिंदोलः; काचं, शिक्यं (with a loop). **2** दोलनं, प्रेंखणं. **3** रयः, वेगः, गति *f.* *-v. t.* प्रेंख् 1 P, दोलायते (D.), इतस्ततः सं-वि-चल् 1 P. *-v. t.* प्रेंख् c., आंदोलयति-प्रेंखोलयति (D.), इतस्ततः सं-वि-चल् c. **-ing,** *a.* प्रेंखत, दोलायमान; काचित, शिक्यित.

Swinge, *v. t.* बलवत् तड् 10. प्रहृ 6 P, दण्डं प्रहृ 1 P.

Swirl, *v. i.* घूर्ण् 6 P, 1 A, भ्रम् 1, 4 P.

Swish *v. t.* वेत्रेण तड् 10 or हन् 2 P or प्र-हृ 1 P.

Switch, *s.* पिंजा, पल्लवः.

Swoon, *v. i.* मुह् 4 P -वि-व्या-°, मूर्छ् 1 P. *-s.* मूर्च्छा, मोहः 'fell in a s.' मोहपरायणो बभूव, मूर्च्छां गतः. **-ing,** *a.* मूढ, मुग्ध, मूर्च्छापन्न, मोहवश.

Swoop, *s.* अवपातः, सहसाक्रमणं-आपतनं. *-v. i.* सहसा अवपत्य ग्रह् 9 U or आक्रम् 1 U, 4 P.

Sword, *s.* असिः, खड्गः, निस्त्रिंशः. कृपाणः, करवा(पा)लः, चंद्रहासः, रिष्टिः, मंडलाग्रः, कौक्षेयकः; 's.-belt' खड्गबंधनं; 's.-stick' कुद्दालं; 's.-man' खड्गिन्, खड्गधरः, आसिकः.

Syce, *s.* अश्वबंधः-पालः.

Sycophant, *s.* चाटुकारः-पटुः, अतिलालनपरः, अत्यनुरोधिन् *m.* **-Sycophancy,** *s.* चाटूक्ति *f.*, चाटुकारित्वं, *See* **Flatter,-y.**

Syllable, *s.* अक्षरं; 'of one s.' एकाच्, एकाक्षर; 'of many s. s' अनेकाच्, बह्वक्षर.

Syllabus, *s.* सारः, संक्षेपः, सारांशः.

Syllogism, *s.* न्यायः. **-Syllogistic,** *a.* न्यायसंगत, न्याय्य, न्याय in comp.

Sylph, *s.* तन्वंगी, तनुगात्री. **2** विद्याधरी. दिव्यांगना.

Sylvan, वन्य, आरण्यक.

Symbol, *s.* चिह्नं, लक्षणं, लिंगं, संज्ञा, प्रतिरूपं. **-ic,** *a.* लाक्षणिक-सांकेतिक (की *f.*), संकेतरूप.

Symmetry, *s.* सौष्ठवं, चतुरस्रता, यथाप्रमाणता, अंगसंयोगः, अवयवसंगति *f.* **-ical** *a.* सम, चतुरस्र, सम-यथा-स-प्रमाण. संगतावयव.

Sympathy, *s.* सहानुभवः, संवेदनं, अनुकंपा. समदुःखता, समदुःखिता; समसुखिता. oft by समदुःख-सुख; 'the birds ever screamed as if out of s.' विहगाः समदुःखा इव चुकुशुः (R. viii. 39). **2** स्वभाव-प्रकृति-साम्यं, आनुगुण्यं, साधर्म्यं आनुरूप्यं. **-etic,** *a.* समदुःख-दुःखिन्, सहृदय, स्निग्ध, सहदुःखिन्,-सुखिन्. **-ize,** *v. i.* सह-सम-दुःखिन्-*a.* भू &c.; *See* (*s.*); 'I s. with you in your distress' त्वद्दुःखदुःखितोहं; त्वत्समदुःखभागहं; 'many s. with us in our success' बहवः अस्मदभ्युदयेन सुखभाजो भवंति-मोदंते-प्रीयंते &c.

Symphony, *s.* एकतानता, स्वरैक्यं, साम्यं; *See* **Harmony.** **-ious,** *a.* सम or संवादिस्वर or ताल.

Symposium, *s.* सह-पान-भोजनं.

Symptom, *s.* लिंगं, लक्षणं; *See* **Indication. -atic,** *a.* सूचक, बोधक.

Synagogue, *s.* समाजः, समागृहं.

Synchronous, *a.* एक-सम-कालीन. **-Synchronism,** *s.* यौगपद्य, समकालीनता. **-Synchronize,** *v. i.* युगपद्-एक-काले-वृत् 1 A or भू 1 P or जन् 4 A.

Syncope, *s.* मूर्छा.

Syndicate, *s.* सभा, संसद् *f.*, सदस् *f. n.*

Synod, *s.* समाजः, सभा, परिषद् *f.* **-ic,** *a.* चांद्र in comp.; (चांद्रमासः).

Synonym, *s.* पर्यायः, तुल्यार्थशब्दः, पर्यायशब्दः. **-ous,** *a.* समानार्थ, तुल्य-एक-अर्थ, सहार्थ.

Synopsis, *s.* सारसंग्रहः-पत्रकं. **-Synoptical,** *a.* सारभूत.

Syntax, *s.* कारकप्रक्रिया, वाक्यरचनाविचारः.

Synthesis, *s.* संयोगः, संकलनं. **-Synthetical,** *a.* सांयोगिक (की *f.*); संयोग in comp.; संयोगात्मक.

Syphilis, *s.* उपदंशः.

Syringe, *s.* शृंग-गकं, बस्ति *m. f.*

Syrup, *s.* मधुरं, मधु *n.*, लेह्यं.

System, *s.* पद्धति *f.*, रीति *f.*, सरणि-णी *f.*, क्रमः, पर्यायः; *See* **Manner. 2** कल्पना, प्रयोगः. **3** शास्त्रं. 4 (Of the body) कायव्यूहः. 5 (Of philosophy) दर्शनं; 'the solar s.' सौरं जगत्. **-atic,** *a.* अनुज्झितक्रम, यथापद्धति, यथाक्रम, क्रमानुगत. **-atically,** *adv.* यथाक्रमं, यथापद्धति. **-atize,** *v. t.* व्यव-स्था *c.* (स्थापयति), यथाक्रमं रच् 10 or विन्यस् 4 U; *See* **Method,-ize,** &c.

Systole, *s.* हृत्संकोचः.

T.

Tabard, *s.* तनुत्राणः.

Tabasheer, *s.* *See* **Manna.**

Tabby, *a.* चित्र, शबल, कर्बुरित.

Tabernacle, *s.* पटवेश्मन् *n.*, पटमंडपः, दूष्यं; (fig.) अचिरस्थायी आवासः.

Tabes, *s.* क्षयः, क्षयथुः.

Tablature, *s.* *See* **Picture.**

Table, *s.* फलकः-कं, आधारः, मंचः; 't. for writing' लेखनाधारः, लिपिसज्जाधारः. **2** पत्रं. **3** (Of metal &c.), पत्रं, फलकं; 'sitting at the same t.' सहभोजिन्, पांक्तेयः; 't. of contents' सूची-निबंध-पत्रं, सूचिपत्री *f.*, अनुक्रमणिका; 't. of numbers' अंकपत्रं-आली; 'be at t.' भुज् 7 A; 'to keep good t.' भोजनविशेषान् उपकल्प् *c.*; 't.-land' अधित्यका, ऊर्ध्वभूमि *f.*, मालं क्षेत्रं, सानु *m. n.*, प्रस्थः; 't.-talk' विश्रंभालापः-कथा. **-Tablet,** *s.* पट्टिका, पट्टः, फलकः, पत्रं; 'on the t. of your heart' हृत्पट्टिकायां **-Tabular,** *a.* पत्राकार.

Taboo, *See* **Interdict.**

Tabor, *s.* मुरजः, मृदंगः.

Tacit, *a.* तूष्णीं कृत, मानस (सी *f.*); 't. consent' मानसाज्ञा; 't. obedience' निर्विकल्प-निर्विवाद-आज्ञापालनं. **-ly,** *adv.* तूष्णीं, जोषं, मूकभावेन, मनसा; निर्विकल्पं.

Taciturn, *a.* संवृतिमत्, मौनिन्, अनालापशील, तूष्णीक, तूष्णींशील, भाषणविरक्त, मितवाक्-कथ. **-ity,** *s.* संवृति *f.*, मौनं, मूकभावः, अनालापः, मितवाक्, कथाविरक्ति *f.*, वाग्यम.

Tack, *v. t.* आ-बंध् 9 P, वि-आ-नह् 4 P. **2** (a vessel) नौमार्गं परि-वृत् *c.* **-s.** कीलकः, गुणः. **-ing,** *s.* नौमार्गपरिवृत्ति *f.*

Tackle, *s.* (नौ-)सज्जा, रज्ज्वादिसामग्री. **-v. t.** सज्जीकृ 8 U, संनह् *c.* **-ing,** *s.* *See* (*s.*) above

Tact, *s.* कौशलं, नैपुण्यं, वैदग्ध्यं, युक्ति *f.*, चातुर्यं; *See* **Skill. -Tactics,** *s.* युक्तिकौशलं; (of war) बलविन्यासकौशलं, व्यूहरचनाविद्या. **-Tactician,** *s.* युक्तिकुशलः, व्यूहपंडितः.

Tactile, *a.* *See* **Tangible.**

Tadpole, *s.* भेकशिशुः-शावकः.

Tag, *s.* अग्रं.

Tail, *s.* लांगू(गु)लं, पुच्छः-च्छं, लूमं; वालहस्तः, वालधिः (bushy end). **-ed,** *a.* पुच्छिन्, लांगूलयुक्त.

Tailor, *s.* सौचिकः, तुन्नवायः, सूचिकः; 't.'s work' सूच्या सेवनं, सूचिकर्मन् *n.*

Taint, *v. t.* दुष् *c.* (दूषयति), लिप् 6 P, कलंकयति (D.). **-s.** दूषणं, कलंकः, दोषः; See **Stain.**

Take, *v. t.* ग्रह् 9 U, प्रति-परि-° (in all senses) अगृहीते राक्षसे (Mu. 1); उपदेशं गृहाण &c.; आ-दा 3 A. प्रति-इष् 6 P; स्वी-अंगी-कृ 8 U. **2** धृ 1 P, 10, आ-अव-लंब् 1 A. **3** (A word in a sense) परि-ग्रह्; तत्रापशब्द आनंतर्यार्थः परिगृह्यते (S. B. 23) 'is taken in the sense of' &c. **4** नी 1 P, वह् 1 P, ह् 1 P. **5** उपलभ् 1 A, अवगम् 1 P. **6** अनुभू 1 P; *See* **Suffer, Affect. 7** लभ्, आप् 5 P, अधिगम्, आ-सद् *c.*; *See* **Get. 8 Captivate,** q. v.; 't. food' आहारं सेव् 1 A; 't. the field' रणभूमिं अवतॄ 1 P, रणाजये युध् 4 A; 't. rest' विश्रम् 4 P; 't. root' मूलं बंध् 9 P; 't. heart' समाश्वस् 2 P, धैर्यं अवलंब्-अवष्टंभ् 9 P; *See* **Courage;** 't. fire' दह् pass., अग्निं उप-इ

2 P; 't. in hand' प्रतिपद् 4 A, उ(ऊ)रीकृ 't. place'; *See* **Happen**; 't. part in' हस्तं दा 3 U, संगिन्-सहकारिन्-सहाय-*a.* भू; 'took part in the massacre' विशसने सहायो बभूव; 't. aim' सं-धा 3 U; 't. one's way' निष्-साध् c. (साधयति), साधयामो वयं (S. 1); 't. effect' फल् 1 P, सफलीभू 1 P; 't. possession of' आक्रम् 1 U, 4 P, आविश् 6 P; 't. to task' निर्भर्त्स् 10 A, परुषं भिद् 1 P. **–***v. i.* सिध् 4 P, संपद् 4 A, गुणं आवह्. 2 आश्रि 1 U, व्रज् 1 P. **–away**, अप-वि-नी 1 P, अप-, हृ 1 P, अप-ऊह् 1 U, विसृज् c.; *S.* **Remove. –back**, सं-प्रतिसं-हृ, प्रत्या-दा, प्रत्यानी. **–down**, अवतॄ c., नि-अव-पत् c., अधो नी. 2 लिख् 6 P. **–for**, मन् 4 A; *See* **Consider**; 'mischievousness is t. en for assiduity' चापल्यमुद्योगितां भजते. **–in**, ग्रह्, सेव्; (in the stomach) ग्रस् 1 A; नि-,ग 6 P. 2 विप्र-लभ् 1 A; *See* **Cheat. –off**, अपनी, अवतॄ c., उन्मुच् 6 P, अवकृष्. **–out**, बहिर्नी, अपनी. **–to**, सेव्, आश्रि, अवलंब्. **–up**, प्रतिपद्, अंगी-स्वी-कृ. 2 आरभ् 1 A, प्रवृत् c. 3 **Occupy, Engross**, q. v. **–upon**, (oneself) अंगीकृ, प्रति-पद्, उ(ऊ)रीकृ; (निर्वाहः प्रतिपन्नवस्तुषु Mu. 2). **–er**, *s.* ग्रहीतृ *m.*, ग्राहिन्-हारिन्-हृत् in comp. **–ing**, *a.* मोहिन्, मनोहारिन्, चित्ताकर्षिन्, मनोज्ञ; *See* **Charming.** 2 ग्राहिन्, &c. **–***s.* आहरणं, ग्रहणं, स्वीकारः.

Tale, *s.* कथा, उप-,आख्यानं, आख्यायिका. 2 परि-,गणना, संख्यानं; 't.-bearer' सूचकः, कर्णेजपः; 't.-bearing' पैशुन्यं, उपजापः.

Talent, *s.* मति *f.*, बुद्धि *f.*, धीशक्ति *f.* प्रज्ञा, बुद्धि or मति प्रभावः or विभवः, बुद्धिकौशलं. 2 गुणः. **–ed**, *a.* धीमत्, प्राज्ञ, सुधी, गुणिन्, गुणवत्.

Talisman, *s.* कवचः-चं, माया, रक्षाकरंडकः.

Talk, *v. i.* आ-सं-लप् 1 P, सं-,भाष् 1 A, संवद् 1 P, संमंत्र् 10 A; *See* **Converse. –***s.* आलापः, संवादः, सं-,कथा, सं-,भाषणं, कथाप्रसंगः. 2 किंवदंती, प्रवादः; *See* **Report**; 'idle t.' प्र-,जल्पितं, प्रलापः; 'popular t.' जनप्रवादः; 'fine t.' शाब्दपांडित्यं; 'mere t.' वाङ्मात्रं. **–ative**, *a.* बहुभाषिन्, जल्पनशील, जल्प(ल्पा)क, वावदूक. **–ativeness**, *s.* वावदूकता, जल्पकता, बहुभाषित्वं. **–er**, *s.* कथकः, वक्तृ *m.*, आलापिन् *m.*

Tall, *a.* उच्च, तुंग, उन्नत, उच्छ्रित, प्रांशु; 't. in stature' उच्च or दीर्घ-देह or मूर्ति; 't. person' प्रांशुः. **–ness**, *s.* उच्चता, उच्छ्रायः, उन्नति *f.*, उच्छ्रायः; 't. of stature' देहदीर्घता-उच्चता.

Tallow, *s.* (मेदादीनां) वसा, वपा; 't. chandler' वसाविक्रयिन् *m.*

Tally, *v. i.* सं-वद् 1 P, तुल्य-अनुरूप-अनुगुण-*a.* भू 1 P; 't.-ing of hands' अक्षरसंवादः. **–***s.* **Match**, q. v.

Talon, *s.* नखः-खं, नखरः-रं.

Tamarind, *s.* चिंचा, तिंतिडी-डिका, अम्लिका, आम्लि(म्ली)का.

Tamarix, *s.* पिचुलः, झाबुकः.

Tambour, –ine, *s.* *See* **Drum** (1).

Tame, *v. t.* वि-नी 1 P, दम् c. (दमयति), निग्रह् 9 P, वशीकृ 8 U; (fury) शम् c. (शमयति). **–***a.* विनीत, दांत, वश्य, अधीन. 2 ग्राम्य, गृहपुष्ट, गृह्य-गृह-ग्राम-in comp; 't. dove' गृहकपोतः; 't. hog' ग्राम्यशूकरः, विड्वरः. 3 निस्तेजस्, नष्टवीर्य; नीरस, निःसत्त्व; *See* **Spiritless. –ed**, *a.* दांत, शांतक्रौर्य, विनीत. **–er**, *s.* विनेतृ *m.*, दमयिता. **–ing**, *s.* दमनं. **–ly**, *adv.* नष्टवीर्यवत्, कापुरुषवत्, क्लीबवत्. **–ness**, *s.* वश्यता, गृह्यता, &c.

Tamper, (with) *v. i.* **Meddle**, q. v. 2 (Witness &c.) कपटेन-छलेन-वशीकृ 8 U; दुष् c. (दूषयति), अन्यथा कृ, विकृ.

Tan, *v. t.* श्यामीकृ 8 U, सं-धा 3 U, शुध् c.; परिष्कृ c. **–ner**, *s.* चर्मकारः, चर्मशोधनकृत् *m.*

Tangent, *s.* स्पर्शः, स्पर्शरेखा.

Tangible, *a.* स्पर्शनीय, स्पृश्य. 2 स्पर्शवेद्य, प्रकट सुस्पष्ट, विभाव्यमान.

Tangle, *v.* **Entangle**, q. v. **–ed**, *a.* जटिल, संमिश्र, संकुल, संकीर्ण.

Tank, *s.* तडागः-गं, जलाशयः, कासारः, वापी, दीर्घिका (large t.); *See* **Pond.**

Tankard, *s.* चषकः.

Tantalize, *v. t.* आशां-तृष्णां-वृध् c., आशां वर्धयित्वा विप्रलभ् 1 A, जाताशाः खंड् 10 or भंज् 7 P. 2 (general) **Cheat**, q. v.

Tantamount, *a.* सम, तुल्य, समार्थक, तुल्यार्थक.

Tantrum, *s.* निष्कारण वैरभावः or दुःशीलं.

Tap, *v. t.* लघु आ-अभि-हन् 2 U or प्र-हृ 1 P 2 छिद्रयति (D.), छिद्रं कृ 8 U. **–***s.* मृदुलघु-चपेटः, लघ्वाघातः-प्रहारः.

Tape, *s.* दीर्घपट्टः-बंधनी.

Taper, *s.* दीपिका, क्षुद्रदीपः.

Tapering, *a.* वृत्तानुपूर्व (K. 1. 35) गोपुच्छाकार, शुंडाकृति.

Tapestry, *s.* चित्रयवनिका.

Tapeworm, *s.* कृमिः, अंत्रकीटः.

Tapis, *s.* *See* **Tapestry.**

Tar, *s.* अ-,रालः, सर्जरसः; *See* **Pitch.**

Tardy, *a.* मन्थरगमन, दीर्घसूत्रिन्, मंद; *See* **Slow.**
Target, *s.* क्षुद्रचर्मन् *n.* **2** शरव्यं, लक्ष्यं-क्षं. **-eer,** *s.* चर्मधरः.
Tariff, *s.* (पण्य-) शुल्कपत्रिका.
Tarnish, *v. t.* दुष् c. (दूषयति). कलंकयति (D.); *See* **Stain.** **-v.** *i.* मलिनीभू 1 P, दुष् 4 P.
Tarpaulin, *s.* सर्जरसलिप्तं क्षौमं.
Tarry, *v. i.* विलंब् 1 A, चिर(रा)यति (D.); अव-स्था 1 A.
Tart, *a.* अम्ल, शुक्त. **-s.** अम्लीय.
Tartar, *s.* दंतशर्करा, मलं, पिप्पिका.
Task, *s.* कार्यं, नियुक्तं कर्म, कर्तव्यं, कार्यभा-(भ)रः, व्रतं; 'one who does a t. imposed' व्रतीनः; 'to take to t.' अधि-क्षिप् 6 P, निर्भर्त्स् 10 A; *See* **Reproach.** **-v.** *t.* कार्यभारं न्यस् 4 U, गुरुकार्ये नियुज् 7 A, 10.
Tassel, *s.* कौशेयसूत्रगुच्छः.
Taste, *v. t.* आ-,स्वाद् 1 A or c., रस् 10, प्राश् 9 P, लिह् 2 U. **-v.** *i.* Oft. by (*s.*). **-s.** आ-,स्वादः, रसः. **2** आ-,स्वादनं, रसनं. **3** (Sense of t.) रसनं, रसनेन्द्रियं, रुचि *f.* **4** अभि-,रुचिः, प्रवृत्ति *f.*, शीलं, व्यसनं; 't. s differ', 'different men have different t. s' भिन्नरुचिर्हि लोकः; 'he was not to her t.' स न तस्या रुच्ये बभूव (K. vi. 44); 'of like t. s' समानशील. **5** रसज्ञता, रसिकता; 'devoid of t.' अ-रसिक, अरसज्ञ. **-er,** *s.* आस्वादकः. **-y, -ful,** *a.* रुचिकर (री *f.*), स्वादु, मिष्ट, सरस, सुरस, रुच्य. **2** हृद्य, मनोहर, हृदय-ग्राहिन्. **-fully,** *adv.* सकौशलं, रसज्ञतया, यथारुचि. **-less,** *a.* नीरस, विरस, रसहीन.
Tatter, *s.* चीरं, चीरचीवरं, लक्तकः, कर्पटः; *See* **Rag.** **-ed,** *a.* जीर्ण, जर्जरित.
Tattle,-er, *See* **Babble,-er.**
Tattoo, *v. t.* रंज् c. **-s.** पटहप्रणादः.
Taunt, *v. t.* आ-अधि-क्षिप् 6 P, निंद् 1 P, उपालभ् 1 A; *See* **Censure.** **2** सोल्लुंठनं-सोत्प्रासेन-वद् 1 P; 'enough of t. ing' अलमलमुपालम्य. **-s.** आ-अधि-क्षेपः, उपालंभः, सोल्लुंठनोक्ति *f.* **-ing,** *a.* साक्षेप, सोपालंभ, आक्षेपगर्भ; *See* **Sarcastic.**
Taurus, *s.* वृषभः,-राशिः.
Taut, *a.* दृढं आतत.
Tautology, *s.* पुनरुक्ति *f.* पुनरुक्तत्वं, पौन-रुक्त्यं. **-ous,** *a.* पुनरुक्त, पुनरुक्तभूत.
Tavern, *s.* मंजा, शौंडापानं, शुंडा; पथिका-श्रमः; 't.-keeper' शौंडिकः.
Tawdry, *a.* बहिरुज्ज्वल, भाण्डशोभन, मिथ्या-शोभायुक्त.
Tawny, *a.* पिंग, पिंगल, पिशंग (गी *f.*), कपिल, कडार, कद्रु.
Tax, *s.* करः, बलिः, शुल्कः-ल्कं, राजस्वं. **2** भारः. **-v.** *t.* करं न्यस् 4 P (with loc.) or दा c. (दापयति) or ग्रह् 9 U (with abl.). **2** आयस् c., अत्यंतं पीड् 10. **3** निंद् 1 P, दोषं ग्रह् 9 U; *See* **Censure.** **-able,** *a.* कराई, शुल्क-कर-अधीन. **-ation,** *s.* कर-ग्रहणं-आधानं, शुल्कसंकल्पनं.
Teach, *v. t.* अधि-इ c. (अध्यापयति), शिक्ष् c., पठ् c., उपदिश् 6 P, शास् 2 P. **-er,** *s.* अध्यापकः, शिक्षकः, गुरुः, उपदेष्टृ *m.*, शास्तृ *m.*; 'religious t.' उपाध्यायः, आचार्यः. **-ing,** *s.* अध्यापनं, शिक्षा-क्षणं, उपदेशः.
Teak, *s.* अर्जुनः; 't.-wood' अर्जुं, अर्जुनकाष्ठं.
Team, *s.* युग्मं or by pl.
Tear, *s.* अश्रु-स्रु *n.*, बाष्पः, अस्रं, नेत्रांबु *n.* -जलं-उदकं, नयनवारि, and sim. comp.; 'with t. s in eyes' सबाष्पं, सास्रं, बा-ष्पाकुलनयन-न.. 'starting of t. s' बाष्पो-द्गमः, उद्बाष्पत्वं; 'flood of t. s' धारास्रु, अश्रुधारा; 'having the eyes filled with t. s' बाष्पाकुल, अश्रुनयन, सास्र, अश्रुमुख, अश्रुपरिप्लुतेक्षण, पर्यश्रु. **-ful,** *a.* सबाष्प, साश्रु अश्रु-संकुल-पूर्ण-परिप्लुत. **-fully,** *adv.* सास्रं, सबाष्पं, साश्रु.
Tear, *s.* छिद्रं, विदरः, भित्ति; *See* **Rent.** **-v.** *t.* वि-,दॄ 9 P or c., वि-,श्र 9 P, विदल् c., भिद्-निर्भिद्- 7 P; 'she tore her hair for grief' विललाप विकीर्ण मूर्धजा (K. iv. 4); 't. to pieces' शकलीकृ, चूर्ण् 10. **-down,** अप-कृष् 1 P, निकृष्. **-off,** आच्छिद् 7 P, अप-नी 1 P, व्यपह् 1 P, निह् 1 P; 't. off the hair' केशान् उल्लुंच् 1 P; *See* **Pull** also; 'I am unable to t. myself off from the cane-bower' निर्गंतुं सहसा न वेतसगृहाच्छक्नोस्मि (S. 3). **-up,** उन्मूल् 10, उत्-वि-पट् 10, उद्-धृ 1 P, उच्छिद्, उत्खन्, व्यपकृष् c. **-v.** *i.* विद्-विभिद्-pass. **2** सवेगं चल् 1 P. **-ing,** *s.* वि-,दारणं, विभेदनं, पाटनं, &c.
Tease, *v. t.* दु 5 P, क्षुभ् c., अर्द् 1 P or c., बाध् 1 A, पीड् 10; *See* **Injure.**
Teat, *s.* वृंतं. **2** चूचुकं, स्तनाग्रं.
Technical, *a.* पारिभाषिक-सांकेतिक-(की *f.*). **-ity,** *s.* पारिभाषिकशब्दः, परिभाषा. **2** पारिभाषिकत्वं. **-ly,** *adv.* परिभाषा-नुसारेण.
Technology, *s.* परिभाषा. **2** शिल्प-कला-विज्ञानं; 'school for t.' शिल्पशाला.
Tedious, *a.* अतिदीर्घ, दीर्घसूत्र, दीर्घतर; 'passes the night ...

श्रमावह, क्लांति-खेद-कर (री *f.*). 3 मंद, मंथर, दीर्घसूत्रिन् चिरक्रिय. **-ly,** *adv.* अति-सु-दीर्घं. **-ness,** *s.* अतिदैर्घ्यं, श्रमावहता; दीर्घता ex. by (*a.*)

Teem, *v. i.* **Abound,** q. v. **2** बाहुल्येन उत्पद् c. or प्र-सू 2, 4 A. **-ing,** *a.* परिपूर्ण, पूर्णगर्भ, आढ्य, समाकुल, आकीर्ण, प्रचुर; *See* **Abundant.**

Teetotal, *a.* मद्यनिवृत्तिविषयक. **-(l) er,** मद्यात् निवृत्तः, निवृत्तमद्यः.

Tegument, *s.* आवेष्टनं, आवरणं, कवचः-चं, पुटः-टं.

Telegram, *s.* विद्युत्प्रेरितवार्ता, विद्युत्संदेशः-वार्ता. **-Telegraph,** *s.* विद्युद्यंत्रं विद्युद्वार्तावहः.

Teleology, *s.* मीमांसा, हेतुविद्या.

Telephone, *s.* दूरभाषणयंत्रं.

Telescope, *s.* दूरदर्शनयंत्रं.

Tell, *v.t.* कथ् 10, आचक्ष् 2 A, शंस् 1 P, आ-नि-विद् c., आ-,ख्या 2 P or c. (ख्यापयति) (with dat.); वर्ण् 10, कथ् 10, श्रु c., नि-,गद् 1 P, व्या-उदा-हृ 1 P, अभि-धा 3 U, निरूप् 10; *See* **Say** also. **2** गण् 10, स-परिसं-ख्या; ' t. beads ' जप् 1 P. **-v.** *i.* सिध् 4 P, सफलीभू 1 P, गुणं-कार्यं-कृ, यशः-सिद्धिं-दा 3 U. **2** (upon) गुणं-कार्यं-जन् c. or उत्पद् c.; अवसद् c; अप-चि 5 U, क्षि 5 P or c. **2** दुर्बलीकृ; *See* **Impair;** ' t.-tale ' सूचकः, पिशुनः, कर्णेजपः. **-er,** *s.* कथकः, आख्यायकः. **-ing,** *s.* कथनं, शंसनं &c.

Temerity, *s.* साहसं, क्षिप्रकारिता, असमीक्ष्य-अविमृश्य-कारिता; *See* **Rashness.**

Temper, *v. t.* संमिश्र् 10, संयुज् 10, संसृज् 6 P. **2** मृदूकृ 8 U, स्निग्धीकृ, प्र-,शम् c. (शमयति), लघूकृ, लघयति (D.), नियम् 1 P; *See* **Moderate.** **-s.** शीलं, प्रकृति *f.*, स्व-,भावः; ' good t. ' सुशीलं, सद्भावः, सौजन्यं; *See* under ' **Good. 2** समता, अक्षोभः, असंभ्रमः, संयमः, रोषाभावः, चित्त-स्वास्थ्यं,-समता; ' to lose t. ' क्षुभ् 4 P, क्रुध्-कुप् 4 P. **3 Anger,** q. v. **-Temperament,** *s.* प्रकृतिः, स्वभावः, देह or शरीर-प्रकृतिः or स्वभावः; 'of a choleric t.' पित्त-प्रकृति. **-Temperate,** *a.* परि-,मित, सम-र्याद, नियत. **2** प्र-,शांत, अक्षुब्ध, धीर, अकोपन, अचंड. **3** संयत, संयमिन्, संयतवृत्ति, संयमशील; ' t. in eating' मिताहार, अल्पाहार, मिताशिन्, संयताहार; ' t. in drinking ' &c.; *See* **Moderate. 4** समशीतोष्ण, मंदोष्ण. **-ly,** *a. v.* धीरं, शांत्या, अक्षोभेण, निरुद्वेगं, शांतचेतसा. **-Temperance,** *s.* संयमः, निग्रहः, परिमितता, नियमः, नियतत्वं, मिताहारः, मिताशनं, मित-

Temperature, *s.* उष्ण-घर्म-परिमाणं.

Tempest,-ous, *See* **Storm,-y.**

Temple, *s.* देवालयः, देवतायतनं-निकेतनं, सिद्धायतनं, देवगृहं-भवनं-मंदिरं, and sim. comp.; मठः, विहारः (Jaina t.); ' endowment of a t.' देवस्वं. **2** कुंभः, कपोलः, शंखः.

Temporal, *a.* ऐहिक-सांसारिक-ऐहलौकिक-प्रापंचिक-लौकिक- (की *f.*).

Temporary, *a.* अचिरस्थायिन्, अचिर-अल्प-कालिक (की *f.*), अशाश्वत (ती *f.*), असनातन (नी *f.*), अचिर, अनित्य, क्षणिक. **-ily,** *adv.* स्वल्पकालं, अचिरं, अशाश्वतं.

Temporize, *v. i.* यथाकालं-यथासमयं-व्यवहृ 1 P; छंदोनुवृत् 1 A **-ing,** *a.* समयानुवर्तिन्, कालानुरोधिन्.

Tempt, *v. t.* प्र-वि-लुभ् c., वि-आ-कृष् 1 P, वि-,मुह् c.; *See* **Allure. 2** परीक्ष् 1 A. **-ation,** *s.* प्र-वि-लोभनं, आकर्षणं, विकारहेतुः, विकारहेतौ सति विक्रियंते येषां न चेतांसि त एव धीराः (K. i. 59) 'there being t. s &c. '; ' liable to t. s ' प्रलोभनास्पदं. **-er,** *s.* प्र-वि-लोभकः मोहकः. **-ing,** *s.* आकर्षिन्, वि-,मोहिन्, प्रलोभिन्.

Ten, *a.* दशन्; ' in t. ways ' दशधा; ' t. times ' दशकृत्वः. **-th,** *a.* दशम (मी *f.*).

Tenable, *a.* रक्षणीय, प्रतिपादनीय.

Tenacious, *a.* ग्राहिन्, संलग्नशील. **2** धारणा-वत्; *See* **Retentive. 3** साग्रह, प्रतिनिविष्ट, आग्राहिन्; दृढसंकल्प, स्वमताग्रहिन्; *See* **Obstinate. 4** श्यान, सांद्र, चिक्कण. **-ness,-Tenacity,** *s.* ग्राहकत्वं, धारणा-शक्ति *f.* **2** ग्राहः; (एको ग्राहस्तु मीनानां), आ-,ग्रहः, अभिनिवेशः, दृढता, श्यानता.

Tenant, *s.* भूम्यधिवासिन् *m.*; (in general) गृहनिवासिन्. **-v. t.** परभूमिं अधिवस् 1 P or अधि-ष्ठा 1 P.

Tend, *v. i.* प्रवणी-भू 1 P, प्रवृत् 1 A, प्रवह् 1 P, उद्दिश् 6 P, अभिसं-धा 3 U; oft. by आलु, शील in comp.; ' t. ing to fall ' पतयालु, पतनशील, पिपतिषु; ' t. ing to the same object ' तदुद्देश; ' t.s to the centre ' केंद्राभिमुखीभवति. **2** (to) आवह् 1 P; क्लृप् 1 A, संपद् 4 A (with dat.), (निष्फलमायमपि मधुमयोजनं न मे धृतिमावहति Rat. 1); कल्पते रक्षणाय &c.; oft. by dat. with or without भू; *See* **Lead. -v. t.** चर् c., पा c. (पालयति), रक्ष् 1 P (of cattle only). **-ency,** *s.* प्रवृत्ति *f.*, प्रवणता, प्रावण्यं, स्वभावः, शीलता-आलुता in comp.

Tender, *a.* सुकुमार, कोमल, मृदु, पेलव; *See* **Delicate, Soft. 2** सुलभवेदन-दुःख, दुःसह, मृदु. **3** बाल, कौमार (री *f.*). 4

hearted ' करुणात्मक, कोमल-मृदु-चित्त, क्लिन्नहृदय, दयार्द्रचित्त —v. t. उपानी 1 P, उपह 1 P. 2 उपक्षिप् 6 P, उपन्यस् 4 U. —s. उपन्यासः, प्रस्तावः. —ly, adv. सकरुणं, सदयं, सानुकंपं,सादरं,करुणार्द्रदृष्ट्या.—ness, s. मार्दवं, कोमलता, स्निग्धता, कारुण्यं, दयालुता, वात्सल्यं, &c.

Tendon, s. शि(सि)रा; स्नायु f., स्नसा. —**Tendinous,** a. शिराल;स्नायुमय (यी f.)

Tendril, s. तंतुः; (of creepers) प्रतानं, किसलयः-यं; See **Shoot.**

Tenement, s. भवनं, आयतनं; 'earthly t.' देहः. 2 स्थावरं.

Tenet, s. मतं, अभिप्राय..

Tenour, s. भावः, भावार्थः, अभिप्रायः, तात्पर्यं. 2 क्रमः, अन्वयः.

Tense, s. कालः. —a आतत. —ion, s. आ-, ततिf.

Tent, s. वस्त्र-पट-वेश्मन् n., दूष्यं-ष्यं, पटमंडपः-गृहं; 'royal t.' उपकार्या, उपकारिका; 'pitch a t.' दूष्यं रच् 10 or उप-क्लृप् c.

Tentative, a. परीक्षार्थं कृत, तत्कालोपयुक्त.

Tenuous, a. See **Thin.** —**Tenuity,** s. See **Thinness.**

Tepid, a. कोष्ण, कवोष्ण, ईषदुष्ण, मंदोष्ण.

Tercentenary, a. त्रिशतवर्षोत्सविन् —s. त्रिशतसांवत्सरिको विधिः.

Tergiversation, s. वाक्छलं, अपलापः; See **Prevarication.**

Term, s. पर्यंतः, अंतः. 2 मर्यादा, अवधिः, सीमा; 'the utmost t.' परमावधिः; 't. of life' आयुर्मर्यादा, आयुःसीमा; 'the t. of life is small' स्वल्पं आयुः. 3 कार्यनिर्वाहसमयः-कालः. 4 पदं, शब्दः, संज्ञा. 5 व्यवहारः, वृत्ति f., भावः; 'on friendly t.s' मित्रभावेन, सद्भावेन, मैत्र्या, सुखेन; 'ill t.s' अप्रीति f., विरोधः, असंतोषः. 6 (Math.) पदं. 7 अवयवः (of a syllogism). 8 (T. s) समयः, संकेतः, संविद् f., प्रतिज्ञा. —v. t. आ-ख्या 2 P, अभि-धा 3 U, आह्वे 1 P; See **Call, Name.** —less, a. निरवधि, अनंत. -inable, a. अंत्य, सीमा in comp. —inal, a. अंत्य,अंतिम. —inus, s. अंतः,सीमन् f. —**Terminate,** v. t. अव-सो 4 P, समाप् c. —v. i. समाप् pass. —ion, s. अंतः, अवसानं, परिणामः, निष्ठा, समाप्ति f., निवृत्ति f. 2 प्रत्ययः.

Termagant, s. अतिकलहप्रिया, कर्कशा, चंडी; See **Shrew, Scold.**

Terminology, s. परिभाषा.

Terpsichorean, a. नृत्यसंबंधिन्.

Terrace, s. अलिंदः,-भूमि f., प्रघा(घ)णः. 2 **Roof,** q. v. 3 वितर्दि f., वेदिका.

Terraqueous, a. जलस्थलात्मक.

Terrene, Terrestrial, a. पार्थिव (वी f.), भौमिक (की f.), भौम (मी f.), भू in comp. 2 लौकिक, ऐहिक (की f.); See **Worldly.** 3 भूचर, स्थलज, भूलोकस्थ; 't. globe' भूगोलः.

Territory, s. प्र-,देशः, राष्ट्र, राज्यं, भूमि f. —ial, a. राष्ट्रिय; by (s.) in comp.

Terror, s. सं-,त्रासः, भयं, साध्वसं, शंका. 2 भयहेतुः- स्थानं, शंकास्थानं; 'a t. to the wicked' शठानां स्वयचिता (Mr. 9). —**Terrible,-Terrific,** a. घोर, दारुण, भीषण, भीम, उग्र, कराल, विकट. —**Terribly,** adv. दारुणं, बलवत्, घोरं, उग्रं. —**Terrify,** v. t. सं-,त्रस् c., भी c., See **Fright,** —ful, &c.

Terse,a. लाघवान्वित, संक्षिप्त, लघुपद. —ness, s. लाघवं, संक्षेपः.

Tertian, s. तृतीयकः-ज्वरः, त्र्यैहिकविषमः (t. ague).

Tertiary, a. तृतीयक, तृतीयिन्.

Test, v. t. परीक्ष् 1 A, (मायां मवेन्द्रस्य परीक्षितोसि R. II. 62), विमृश् 6 P, (ज्ञात्वं प्रयोगे च मां विमृशतु M. 1). —s. परीक्षा, विमर्शः, प्रतीति f. 2 प्रमाणं, (something whereby to t.) निकषः, निकषग्रावन् m.; 'this should be put to t.' एतत्प्रतीतिकस्पाया; See **Touch.**

Testaceous, a. कंबुविशिष्ट, शंखवासिन्.

Testament, s. मृत्युलेखः-पत्र, इच्छापत्रं. 2 संहिता. —ary, a. मृत्युपत्रदत्त.

Testator, s मृत्युलेखकर्तृ m.

Testicles, s. अंडः,-कोषः-शः, मुष्कः, वृषणः फलं (in dual).

Testify, v. t. साक्ष्यं दा 3 U, प्रमाणयति (D.), प्रमाणीकृ 8 U. 2 प्रकाश् c., विवृ 5 U, व्यंज् 7 P or c., प्रकटीकृ; आविष्कृ; (by words) ब्रू 2 U, वच् 2 P &c

Testimony, s. साक्ष्यं, प्रमाणं, प्रामाण्य —**Testimonial,** s प्रमाणपत्रं-लेखः.

Testy, a. See **Fretful.**

Tetanus, s. धनुर्वातः.

Tete-a-tete, s. रहः-संलापः-प्रस्तावाः f.

Tether, s. बंधनरज्जु f.-सूत्रं. —v. t. (रज्ज्वा) बंध् 9 P.

Tetrad, s. चतुष्टयं, चतुष्कं.

Tetragon, s. चतुर्भुजः, चतुरस्रं. —al, a. चतुरस्र, चतुष्कोण.

Text, s. मूलं, मूलपंक्ति f., मूलग्रंथः. 2 श्रुति f., सूत्रं, वचनं, वाक्यं —ual, a. मौलिक (की f.), मौल (ली f.).

Textile, a. तांतव (वी f.), तंतुनिर्मित

Texture, s. विन्यासः, वि-,रचना-नं, 3 वृत्ति f., वापः-यः. 2 तंतु-सूत्र-गुणः. 3 तांतवं.

Tew v. t. See **Ply.**

Than, conj. Ex. by abl. of word following it; मत्तोऽपि बलवत्तरः &c.; with

'better' ex. by न च, न तु, न पुनः; *See* **Prefer, Better;** oft. ex. by अपेक्ष्य (with acc.), अपेक्षया in comp.

Thank, *v. t.* उपकृत-अनुगृहीत-*a.* अस्मि इति वद् 1 P, ('Say,' q. v.); कृतज्ञतां दृश् c. or आविष्कृ 8 U, कृतोपकारं स्तु 2 U or प्रशंस् 1 P; 't-ed his deliverer' भवतानुगृहीतः-उपकृतः-अस्मि इति रक्षितारमुवाद; '(I) t. you', 'thanks' अनुगृहीतोस्मि, महाननुप्रसादः. 't. God' दिष्ट्या. **-s.** (Thanks) कृतज्ञतादर्शनं-प्रकाशनं, उपकारस्तुति *f.*, धन्यवादः; better ex. by (*v.*); 'accept my t. s' by (*v.*). **-ful,** *a.* कृतज्ञ, कृतवेदिन्, उपकारज्ञ, कृतज्ञतादर्शिन्. **-fully,** *adv.* कृतज्ञतापूर्वं, कृतज्ञतया. **-less,** *a.* अकृतज्ञ, कृतघ्न. **-Thanksgiving,** *s. See* (*s.*).

That, *a.* तद् (सः-सा-तत्). **2** यत् ((यः-या-यत्), oft. by comp.; 'he t. has strength' सबल, बलिन् &c. **-*conj.*** इति (after assertions) यथा, यत् (at beginning) with or without इति; sometimes not ex. **2** (Purpose) इति with pot. mood or अर्थं in comp.; 'Oh t.' *See* **Would.**

Thatch, *s.* छदिस् *f.*, पटलं, तृणपटलं-छदिः. **-*v. t.*** तृणच्छदिना आ-,छद् 10. **-er,** *s.* तृणपटलकारः.

Thaw, *v. i.* ~~द्रु 1 P, विली 4 A. or caus. द्रु c.~~, द्रवीकृ, वि-ली c.; *See* **Melt.** **-s.** हिम or तुषार-द्रुति *f.* or स्रावः.

The, (Article) Ex. by तद् (सः-सा-तत्) or अदस् (असौ-अदः), gen. not ex. **2** (With comp. adj.) by यथा यथा-तथा तथा; यथा यथा यौवनमतिचक्राम तथा तथा अनपत्यताजन्मा अवर्धतास्य संतापः (Ka. 59), 't. older he grew, t. greater his torment' &c.; 't. sooner, t. better' यथा यथा लघु कार्यं संपाद्यते तथा तथा अधिकं श्रेयोभवेत्; 't. more so' विशेषतः, विशेषेण.

Theatre, *s.* रंगः,-भूमि *f.*,-शाला, नृत्य-नाट्य शाला, नाटकगृहं. **-Theatrical,** *a.* नाटक, नाट्य in comp.; 't. performance' नाटकप्रयोगः.

Theft, *s. See* under Thieve.

Theism, *s.* ईश्वरवादः, आस्तिक्यवादः, आस्तिक्यं. **-Theist,** *s.* ईश्वरवादिन् *m.*, आस्तिकः.

Theme, *s.* विषयः, प्रकरणं, वस्तु *n.*, प्रबंधः.

Then, *adv.* तदा, तदानीं, तस्मिन्काले. **2** ततः, अनंतरं, अथ. **3** तर्हि; तत्; 'now and t.' कदापि, कदाचित्; 'so t.' एवं, तर्हि; 'what t.' ततः किं. **-Thence,** *adv.* ततः, तस्मात्, तस्मात् स्थानात्; 't.-forth', 't. forward' ततः प्रभृति-आरभ्य, तदाप्रभृति.

Theocracy, *s.* ईश्वरप्रभुत्वं, ईश्वरकर्तृकत्वं.

Theogony, *s.* देवोत्पत्ति *f.* -वंशः.

Theology, *s.* ईश्वर-ब्रह्म-ज्ञानं, परमार्थविद्या, अध्यात्म-ज्ञानं-विद्या. **-ian,** *s.* परमार्थविद् *m.*, ईश्वरज्ञानविशारदः, ब्रह्म-विद्-ज्ञानिन्, वेदांती, अध्यात्मवादी. **-ical,** *a.* ex. by (*s.*) in comp., आध्यात्मिक-पारमार्थिक- (की *f.*).

Theorem, *s.* प्रमेयोपपाद्यं.

Theory, *s.* मतं, सिद्धांतः; वादः; 't. of evolution' परिणामवादः; नास्तिकमतं &c. **2** कल्पना, तर्कः, मनःसृष्टि *f.* **3** आगमः, शास्त्रं, उपपत्ति *f.* (as opp. to 'practice' प्रयोगः), शास्त्रेष्वप्यागमिनौ प्रयोगनिपुणौ च (M. 3) 'well versed in t. and practice'; oft. मंत्रतंत्रं 't. and practice.' **-Theoretical,** *a.* व्यवहारायोग्य, काल्पनिक- अव्यावहारिक- (की *f.*). **-ally,** *adv.* कल्पनापूर्वं. **-Theorize,** *v. t.* मतं उपकल्प् c.

Theosophy, *s.* ईश्वरवादः-ज्ञानं. **-ist,** *s.* अध्यात्मविद्.

Therapeutic, *a.* शांतिकर (री *f.*), रोगघ्न (घ्नी *f.*); 't. s' भेषजशास्त्रं.

There, *adv.* तत्र, तस्मिन्स्थाने, तत्स्थले. **2** (Expletive) by अस्ति. **-*interj.*** पश्य, पश्य; 'here and t.' इतस्ततः; 't.-about' (t. s) तत्रैव कुत्रापि; तत्स्थानसमीपे; (with number) उप-आसन्न in comp.; *See* **Nearly, About;** '20 or t.-abouts' उप-आसन्न-विंशाः (नराः) &c., 't.-after' ततः, तदनु, ततः परं, तदनंतरं; 't.-at' तेन, तत्र; तदुपरि; ततः; 't.-by' तेन; तेनोपायेन, तद्द्वारेण; 't.-fore' अतः, तस्मात्, तस्मात् कारणात्-हेतोः, ततः; तत्, इति हेतोः, अनेन कारणेन-हेतुना; 't.-in' तस्मिन्विषये; 't.-of' तत्रत्य, ततस्त्य, तत्रस्थ (*a.*); तस्य, अस्य, तदीय; 't.-upon' ततः, &c.

Thermal, *a.* उष्णतासंबंधिन्.

Thermometer, *s.* उष्णमापकयंत्रं.

Thesis, *s.* प्रतिज्ञा, पूर्वपक्षः. **2** प्रबंधः.

Thews, *s. See* **Muscle,** (1). **2** शरीरबलं.

Thick, *a.* घन, निबिड, अविरल, सांद्र, गाढ; नीरंध्र, इद्धान. **2** स्थूल, महत्, विपुल; *See* **Large.** **3** मंद, जड, स्थूल; *See* **Dull;** 't.-headed' मंदधी; 't.-skinned' कठिन, सहिष्णु; मंद, स्थूल. **4** पंकिल, कलुषित, आविल. **5** (Of a solid body) घन. **-s.** तुमुलं, शिरस् *n.*, मूर्धन् *m.*, संकुलं; 'in the t. of the fight' रणशिरसि, रणसंमर्दभूमि. **-*adv.*** अविरतं, निरंतरं, अविरलं, निबिडं, by (*a.*) in comp.; 't. sown' घनोप्त, सांद्रोप्तादिस &c; 't-set' ह-, संहत, उपचित.

-en, *v. t.* घनीकृ 8 U, निबिडीकृ &c. -*v. i.* घनीभू 1 P, निबिडीभू; 'the horizon t. -ed' दिङ्मंडलं (अभ्रपटलैः) घनीभूतं, अभ्रपटलाकीर्णं. -et, *s.* गहनं, गुल्मः-ल्मं, निबिडारण्यं, वृक्ष-तरु-गहनं. -ly, *adv.* निरंतरं, अविरलं, निबिडं, गाढं. -ness, *s.* घनता, सांद्रता, संहति *f.*, &c. 2 बेधः, घनता, पिंडत्वं. 3 (Of voice) स्वरभंगः.

Thieve, *v. t.* चुर् 10, मुष् 9 P, स्तेन् 10. -ish, *a.* अपहरण or चौर्य-शील or वृत्ति. चौर्यासक्त. -ishness, *s.* चौर्यासक्ति *f.* -**Thief,** *s.* स्तेनः, चोरः, चौरः, तस्करः, दस्युः, मोषकः, कुंभीलकः, पा(प)टच्चरः, प्रतिरोधिः, परास्कंदिः, मलिम्लुचः, एकागारिकः. -**Theft,** *s.* स्तेयं, मोषः, चौर्यं, चो(चौ)रिका, स्तैन्यं.

Thigh, *s.* ऊरुः (*m.*), सक्थि *n.*; 'having beautiful t. s' वामोरुः-रू.

Thimble, *s.* अंगुलित्राणं, अंगुलिशस्त्रं.

Thin, *a.* प्र-,तनु, सूक्ष्म, विरल, अस्थूल, श्लक्ष्ण. 2 कृश, क्षीण, शांत; 'grown t.' तन्वंग-कर्शितांग (गी *f.*); 'having a t. waist' तनुमध्यम, क्षीणमध्यम; *See* **Slender.** -*v. t.* विरलयति (D.), ऊनी-विरली-कृ 8 U, संख्यां अप-चि 5 U or क्षि 5 P or c. 2 तनूकृ, तक्ष् 1, 5 P, उल्लिख् 6 P. -ly, *adv.* विरलं, असंहतं. -ness, *s.* तनुता, सूक्ष्मता, वैरल्यं, कार्श्यं; क्षीणता.

Thing, *s.* वस्तु *n.*, द्रव्यं, पदार्थः, अर्थः. 2 विषयः, अर्थः.

Think, *v.* चिंत् 10, ध्यै 1 P, विमृश् 6 P, आ-पर्या-लोच् 10, वि-,तर्क् 10, वि-चर् c., मनसा क्लृप् c., सं-,भू c. 2 मन् 4 A, गण् 10; *See* **Consider;** 't. much of' बहु मन्; 'I t. so' इति मे मतिः; 'dose not t. of going to his capital' नगरगमनाय मतिं S. 2); 't. of' स्मृ 1 P, मनसि कृ 'I never thought of winter' हेमंतः समुपस्थास्यति इति चिंता नैव मनसि कृता, इति नचालोचितं. -er, *s.* सूरिः, सुनिः; (lit.) चिंतकः; *See* **Philosopher.** -**Thought,** *s.* (act) चिंता, ध्यानं; आलोचनं; (result also) विचारः, विमर्शः, विचारणा-णा, भावना, मनोव्यापारः, चित्तचेष्टा. 2 मतं, अभिप्रायः, मनोरथः. 3 मति *f.*, बुद्धि *f.*, कल्पना, विचारः, संकल्पः, मनोगतं, चित्तं, मनस् *n.*, तर्कः, चित्त-मनो-वृत्ति *f.*, भावना; 'one's inmost t. s' अंतर्गतं मनः; 'evil t.' कुमतिः; 'benevolent t.' परहितबुद्धिः; 'swift as t.' मनोजव; 'beyond t.' अचिंत्य; 'in t., word or (actual) deed' मनोवाक्कायकर्मभिः. -ful, *a.* चिंताशील, विचार-विवेक-शील, विमृश्य-समीक्ष्य-कारिन्, असाहसिक (की *f.*), सावधान, अप्रमत्त. 2 चिंता-कुल-पर-निमग्न, ध्यानपर. -fully, *adv.* विचिंत्य, विमृश्य, विचार्य, समीक्ष्य, सविवेकं, पर्यालोच्य. -fulness, *s.* सुविचारता, विवेकिता, समीक्ष्यकारिता. -less, *a.* प्रमत्त, अनवहित, असावधान, *See* **Negligent.** 2 निश्चिंत, वीतचिंत. 3 असमीक्ष्य-अविमृश्य-कारिन्, क्षिप्रकारिन्, विवेक-विचार-हीन, सदसत्, मूढ. -lessly, *adv.* मोहात्, रभसा, अविमृश्य, अविवेकेन, अविचारेण. -lessness, *s.* अविवेकः, अविचारः, रभसः, मोहः.

Thirst, *v. t.* तृष् 4 P, (fig. also); पा desid. (पिपासति), उदन्यति (D.). -*s.* तृष्णा, (fig. also); द्रव्यतृष्णा, जीवितवृष्णा &c.; पिपासा, तृषा, तृष् *f.*, उदन्या, पानेच्छा. -y, *a.* तृषित, पिपासित, तृषार्त-आकुल-आतुर, सतृष्ण, पिपासु, उदकार्थिन् तृष्णाविष्ट-आक्रांत.

Thirteen, *a.* त्रयोदशन्. -th *a.* त्रयोदश (शी *f.*).

Thirty, *a.* त्रिंशत् *f.* -ieth, *a.* त्रिंश (शी *f.*), त्रिंशत्तम (मी *f.*).

This, *pron. a.* एतद् (एषः-एषा-एतत्), इदं (अयं-इयं-इदं); 't. way', 't. way' इतः इतः.

Thistle, *s.* गोक्षुरः-रकः, गोकंटकः, श्वदंष्ट्रः, स्वादुकंटकः, पलंकषा, इक्षुगंधा, श्वदंष्ट्रा, (plant).

Thither, *adv.* तत्र. -ward, *adv.* तं देशं प्रति.

Thong, *s.* वरत्रा, व(ब)ध्री, चर्मरज्जु *f.*

Thorax, *s.* उरः-वक्षः *n.*,-स्थलं.

Thorn, *s.* कंटकः-कं, शल्यं; शिताग्रः, वक्र-कुसुमकः; (fig.) कंटकः, शल्यं; 'he is a t. in your side' अंतःप्रस्तुतं शल्यं-कंटकं-इव स त्वां पीडयति; 'there is no rose without a t.' सुखं नाम दुःखमिश्रितमस्त्येव, दुःखासंभिन्नं सुखं नैव प्राप्यते. 2 कंटलकता-वृक्षः; 't.-apple' धत्तूरः, धुस्तरः, उन्मत्तः, कितवः, धूर्तः, कनकाह्वयः, मातुलः, मदनः; (fruit) मातुलपुत्रकः. -less, *a.* निष्कंटक. -y, *a.* कंटकावृत, कंटकाकीर्ण, कंटकित, सकंटक.

Thorough, *a.* संपूर्ण, सम्यच्, साद्यंत, पर्याप्त; *See* **Complete**; 't.-bred' अभिजात, अतिकुलीन; (horse) आजानेयः, कुलीनः; 't.-fare' राजमार्गः, घंटापथः, संसरणं; सर्वसामान्यपथः, सर्वजनपथ्यमार्गः. -ly, *adv.* सम्यक्, संपूर्णं, साद्यंतं; by पार in comp.; 'who has t. learnt the lores' विद्यानां पारदृश्वनः (R. i. 23); 't. mastered all lores' ससार सर्वा विद्याः (R. iii. 30). -ness, *s.* पूर्णता, परिपूर्ति *f*, विशेषता.

Thou, *pron.* त्वं; 'to t. and thee' त्वंकृ 8 U; 'do not t. your elders' गुरुषु त्वंकारं न प्रयोजयेत्. -**Thine,** *a.* त्वदीय, तावक (की *f.*), तावकीन, त्वत्क, भवदीय, त्वत् in comp.

Though, *adv.* अपि, यद्यपि; 'as t.' इव.

Thousand, *a., s.* सहस्रं, दशशतं; 't.s of times' सहस्रशः-वारं; 'in a t. ways or parts' सहस्रधा; 'ten t.' अयुतं; 'hundred t. लक्षं; 'by t. s.' सहस्रशः **-th,** *a.* सहस्रतम (मी *f.*).

Thrall, *s.* दासः. **-dom,** *s.* दास्यं, दासवृत्ति *f.*, दासत्वं; *See* **Slave,-ery. 2** वशता, पारतंत्र्यं, अधीनता.

Thrash, *v. t.* परुषं-बलवत्-तड् 10 or प्र-हृ 1 P. **2** निस्तुषीकृ 8 U, पू 9 U; *See* **Thresh.**

Thread, *s.* सूत्रं, तंतुः, (fig. also), (आशातंतुः), गुणः,तंत्रं; 't. of a story' कथाप्रबंधः-अनुबंधः-संदर्भः-अन्वयः,अनु-,संधानं,प्रबंधार्थः; 't.-bare' सूत्रदरिद्र; अयं पटः सूत्रदरिद्रतां गतः (Mr. 2), सूत्रशेष; जर्जर. **—***v. t.* सूत्र् 10; गु(गुं)फ् 6 P, ग्रंथ् 9 P; 't. one's way' मंदं मंदं प्रसृप् 1 P. **-y,** *a.* सूत्र-तंतु-मय (यी *f.*).

Threat, *s.* तर्जनं, तर्जितं, भर्त्सनं, अपकारगिर् *f.* **-en,** *v. t.* सं-,तर्ज् 1 P, 10 A, निर्-, भर्त्स् 10 A, भी c. **—***v. i.* प्रत्या-सद् 1 P, लग्न-*a.* संपद् 4 A, उपक्रम् 1 P; 'war t.s' प्रत्यासीदति रणप्रसंगः; *See* **Impend. -ening,** *a.* भर्त्सनकृत्; अनिष्टसंवादिन् प्रत्यासन्नभय, विभीषक. **-eningly,** *adv.* तर्जयत्-*a*.

Three *a.* त्रि (तिसृ *f.*); 'aggregate of t. त्रयं, त्रितयं, त्रिकं, त्रयी; 't. months' त्रिमासं, मासत्रयं; 'two or t.' द्वित्र, त्रिचतुर, &c.; 't.-cornered' त्रिकोण; 't.-eyed' त्रिलोचनः, त्रिनयनः; &c.; 't.-fold' त्रिगुण; 't.-fourths' त्रिपादः, पादत्रयं; '2 and t.-fourths' पादोनत्रयं. **-Third,** *a.* तृतीय. **—***s.* तृतीयभागः-अंशः. **-ly,** *adv.* तृतीयस्थाने **-Thrice,** *adv.* त्रिः, त्रिवारं.

Thresh, *v. t.* मृद् 9 P, परि-,पू 9 U, निस्तुषीकृ 8 U, कंड् 10. **2** तड् 10, प्र-हृ 1 P. **-ed,** *a.* निस्तुषित, निस्तुष, पूत, बहुलीकृत. **-ing,** *s.* पावनं, बहुलीकरणं, कंडनं, निस्तुषीकरणं; 't. floor' खलधान्यं; 't. instrument' मुसलः-लं. अयोग्रं, कंडनी.

Threshold, *s.* देहली, द्वारपिंडी, ग्रहावग्रहणी; (fig.) प्रारंभः.

Thrift, *s.* मितव्ययः-व्ययिता. **2** सं-वि-वृद्धि *f.* **-y,** *a.* मितव्ययिन्, अल्पव्यय; *See* **Frugal.**

Thrill, *s.* प्र-,कंपः, स्फुरणं, हर्षः; (of joy, horror, &c.) रोमांचः, पुलकः; उद्धर्षः; 't. of joy' हर्षरोमांचः, पुलकोद्गमः, रोमहर्षः, 'a t. came over her body' तस्या गात्रं रोमांचितं-पुलकितं-कंटकितं-बभूव; 'with a t. of horror' साध्वसरोमांचितगात्रः. **—***c.* स्फुर् 6 P, हृष् 4 P, प्र-,कंप् 1 A; gen. ex. by पुलकित, रोमांचित, कंटकित, (*a.*); 'be t.-ed with joy' आनंदपुलकिततनुर्बभूव. **-ing,** *a.* लो(रो)महर्षण (णी *f.*), पुलकित, रोमांचित, &c.

Thrive, *v. i.* प्र-,वृध् 1 A, प्र-उप-चि pass., संऋध् 4, 5 P, उन्नतिं-उत्कर्षं-आप् 5 P; *See* **Prosper, Flourish. -ing,** *a.* वर्धिष्णु, प्र-उप-चीयमान, समृद्ध.

Throat, *s.* कंठः, गलः, कृकः, निगरणः; 'relating to t.' कंठ्य; 'up to the t.' आकंठं, आकंठात्.

Throb, *v. t.* प्र-,स्पंद् 1 A, स्फुर् 6 P, वेप् 1 A, कंप् 1 A. **-bing,** *s.* स्पंदः, स्पंदनं; स्फुरणं, स्फुरितं, कंपः.

Throe, *s.* यातना, वेदना, व्यथा; (of delivery) प्रसववेदना, प्रसवकालव्यथा.

Throne, *s.* सिंहासनं, नृपासनं, &c.; भद्रासनं; 'ascended the ancestral t.' भेजे पैतृकमासनं (R. xvii. 28); 'getting the t.' राजपदावाप्ति *f.*; 'having lost his t.' छत्रभ्रष्टः. **—***v. t.* अभिषिच् 6 P, राज्ये अभिषिच्, सिंहासनं आरुह् c.; 't. ed king' अभिषिक्तो राजा.

Throng, *s.* जनसंमर्दः-संकुलं, लोकनिवहः. **—***v. t.* आ-समा-कॄ 6 P, संबाध् 1 A. **—***v. i.* जनाकीर्ण-जनसंबाध-*a.* भू; *See* **Crowd. -ed,** *a.* आ-समा-कीर्ण, जनसंकुल-संबाधित.

Throttle, *v. t.* गलं निष्पीड् 10, गलनिष्पीडनेन व्या-पद् c., गलहस्तयति (*D.*).

Through, *prep.* Ex. by instr. or abl. **2** मध्येन, अंतरेण; 't. the branches' विटपांतरेण. **3** पारं, तीरांतरं यावत्. **4** मुखेन; द्वारेण, द्वारा, in comp; सखीमुखेनोचे 'spoke t. her friend'. **—***adv.* समग्रं, साद्यंतं, शेषं यावत्, आसमाप्तेः; oft. by पारं गम् or दृश् 1 P; 'he has learnt the Vedas t.' श्रुतिपारं गतः, श्रुतिपारदृश्वा, 'to get t.' तारयति-पारयति (D.), समाप् c. **-Throughout,** *prep.* Ex. by सर्व, समस्त; *See* **All;** आ or यावत् in comp.; 't. one's life' यावज्जीवं-वेन, आजीवितांतात्; 't. the town' अखिले नगरे, नगरे सर्वत्र. **—***adv* सर्वत्र, अशेषतः; सर्वत्र वैतालीयं छंदः 'the metre is Vaitālīya t.'

Throw, *v. t.* प्र-,क्षिप् 6 P, प्र-,अस् 4 P, पत् c., प्र-,मुच् 6 P, विसृज् 6 P, ईर् c., प्रेष् c., (with loc. of place); 't. a glance' दृष्टिं-चक्षुः-क्षिप् or दा 3 U or पत् c.; 't. into disorder' विजली-आकुली-कृ 8 U, व्यूह् भंज् 7 P; 't. dice' अक्षान् आवप् 1 P or पत् c. **-about,** उत्-वि क्षिप्, इतस्ततः चल् c.; बाहूत्क्षेपं 't. ing about the arms.' **-away,** निः-वि-क्षिप्, अपास्,

अप-हा 3 P, अपव्यध् 4 P, त्यज् 1 P; (time) क्षिप्, हृ 1 P यं c. (यापयति). 2 निरस्, प्रत्याख्या 2 P; *See* **Reject;** 'it was t.-ing words away' निरर्थकं-मोघं-एव तव भाषणं, वाचावासमरत्वकं भाषणं; 'kindness was not thrown away upon him' सोऽस्मृत कृतज्ञतयास्मरत्; 'to be thrown away pon' विफलीभू 1 P, विफलतां गम् 1 P, लर्थ-क्षर्य-नाशं-गम्-या &c.; गता नाशं तारा उपकृतमसाधाविव जने (Mr. 5); असत्पुरुषसेवेव दृष्टिर्विफलतां गता (Mr. 1). **-down,** पत् c., अधः क्षिप् or पत्; प्र-भ्रंश् c., प्र-च्यु c. **-off** निः-प्र-क्षिप्, अव-सिह्-धू 5, 9 U, निराकृ, अपव्यध्, अप-सृ c.; 't. one off his guard' असावधान-*a.* कृ; 't. off the veil or mask' स्वरूपं प्रकटीकृ or वि-वृ 5 U or प्रकाश् c. **-out, Reject,** q. v. 2 निः-,सृ c., अपास्. 3 (Hints) सूच् 10, उप-क्षिप्, उपन्यस्, व्यंज् c. **-up,** उद्स्, उत्क्षिप् &c. (from the stomach) उद्वम् 1 P, उद्-गृ 6 P, 'I have thrown a wall around' उपक्षिप्तो मया भित्तिबंधः (M. 5). **-s.** प्र-,क्षेपः-पणं, प्रासनं, प्रेरणं &c. **-er,** *s.* क्षेप्तृ *m.*, प्रासकः.

Thrum, *s.* दशाः-वस्त्रयः (pl.).

Thrush, *s.* सारिका, शारिका *f*

Thrust, *v. t.* अपव्यध् 4 P, प्र-सृ c., प्र-क्षिप् 6 P; 't. away', 't. out' निरस् 4 U, निः-सृ c., बहिष्कृ 8 U; (the hand &c.) प्र-सृ c.; 't. into' प्र-नि-विश् c.; 't. on' प्रयुज् c., c. प्रचल् c. **-s.** आघातः, प्रहारः ताडनं; (with fist) मुष्टिप्रहारः-आघातः.

Thumb, *s.* अंगुष्ठः; 'under one's t.' आयत्त, वश्य. **-v. t.** अंगुष्ठेन परामृश् 6 P or स्पृश् 6 P or अंक् 10.

Thump, *v. t.* आहन् 2 U, तड् 10, प्र-हृ 1 P. **-s.** आ-अभि-घातः, प्रहारः.

Thunder, *s.* मेघगर्जनं, घनध्वनिः, जीमूतस्तनितं, मेघगर्जितं; and sim. comp.; वि-, स्फूर्जथुः- थुः, स्फूर्जितं, स्तनितं, रसितं;गर्जितं, गर्जनं-ना; 't.bolt' वज्रः-ज्रं, कुलिशं, भिदुरं, पविः, अशनि *m f.*, शतकोटिः, स्वरुः, शंबः, ह्रादिनी, दंभोलिः; 't. clap' वज्रनिर्घोषः-निर्घातस्वनः-निष्पेषः; *See* (*s.*); 't.-storm' अशनिवर्षः-पातः; 't.-struck' अशनिताडित,वज्राहत,*See* **Astounded.** **-v.** गर्ज् 1 P, स्तन् 1 P, वि-स्फूर्ज् 1 P; 'shouldst t. reproof' यत्त्वं (साक्षेपमिव) नदसि सिंहनादैः (Mr. 5). **-er,** *s.* वज्रिन् *m.*, कुलिशभृत, वज्रपाणिः.

Thursday, *s.* गुरुवासरः.

Thus, *adv.* एवं, इत्थं, इति. अनेन प्रकारेण, अनया रीत्या.

Thwack. *See* **Smack.**

Thwart, *v. t.* खंड् 10, वि-प्रति-हन् ... P, मोघीकृ 8 U.नि-प्रति-वि-रुध् 7 U; ...यति-प्रतीपयति (D.); क ईप्सितार्थस्थिरनिश्चयं मनः प्रतीपयेत् (K. v. 5); *See* **Frustrate, Baffle.**

Tiara, *s.* मुकुटं, किरीटः, मौलिः.

Tick, *s.* यूका. 2 **Credit,** q. v.

Ticket, मिर्द्धकानी, अभिज्ञानपत्रं.

Tickle, *v.* कुतकुतयति (D.), कंडूयति (D.); (fig.) **Please, Gratify,** q v. **-er,** *s.* कंडूयनकः.

Tide, *s.* वेला (of the sea). 2 स्रोतस् *n.*, ओघः, वेगः, रयः; *See* **Stream.** **-v. t.** (over) तॄ 1 P, सं-उत्-°.

Tidy, *a.* **Neat,** q v.

Tidings, *s.* वार्ता, प्रवृत्ति *f.*, *See* **News.**

Tie, *v. t.* नि-,बंध 9 P, पिनह् 4 P: (together) योक्त्रयति (D.), संबंध्, संश्लिष् c., संसंज् c., सं-युज् 7 U, 10, संधा 3 U; (flowers &c.) गुंफ् 6 P, सं-ग्रंथ् 9 P. **-s.** निबंधनं, (द्वितीयं मनसो निबंधनं); संश्लेषणं, बंधः-धनं-नी, ग्रंथिः; 't. of a yoke' योक्त्रं, आबंधः; 'this (child) is the mutual t. of parents' एतदन्योन्यसंश्लेषणं पित्रोः (U. 3). 2 दामन् *f. n.*, गुणः, तंतुः. 2 **Fetter,** q. v. 4 संगः, बंधः; 'worldly t. s' संसारबंधः; 'free from t. s' निः-संग, मुक्तसंग. **-er,** *s.* पंक्ति-श्रेणि-*f.*; *See* **Line.**

Tiffin, *s.* उपाहारः.

Tiger, *s.* व्याघ्रः, शार्दूलः, द्वीपिन् *m.*

Tight, *a.* अशिथिल, दृढ, गाढ, संसक्त, सुसंहत. 2 अतिपिनद्ध, गाढ-दृढ-बद्ध, संनिबद्ध; 'I am chained down by this t. bark-garment' अतिपिनद्धेन वल्कलेन नियंत्रितास्मि (S. 1); 'the coat sits t. on your body' अंगानंतरवर्ती-अंगसंसक्तः-कंचुकः. 3 आतत. 4 संबाध. **-en,** *v. t.* दृढीकृ 8 U, नियम् 1 P, दृढयति (D.). **-ly,** *adv.* दृढं, प्र-गाढं, अशिथिलं; 'tied t.' दृढबद्ध &c. **-ness,** *s.* दृढता,घनता, सुसंसक्ति *f.*, संहति *f.*, आनंतर्यं.

Till, *adv. prep.* यावत् (with acc. of noun) or यावत् न (followed by तावत्); 't. now' अद्यावधि, अद्य यावत्; gen. by आ in comp. or with abl.; 't. death' आमरणं, आमृत्योः; 't. the learned are satisfied' आपरितोषाद्विदुषां (S. 1). **-v. t.** कृष् 1 P, 6 U. **-age, -Tilth** *s.* कृषिकर्मन् *n.*, कृषि *f.* **-er,** *s.* कृषकः, कर्षकः, कृषीवलः; क्षेत्राजीवः.

Tilt, *s.* वितानं, उल्लोचः. 2 प्रासक्रीडा-युद्धं. **-v. t.** आवृज् 10. 2 प्रासयुद्धे प्रवृत् 1 A. **-v. i.** आ-अव-नम् 1 P, भुज् 6 P.

Timber, *s.* काष्ठं, दारु *n.*

Timberel, *s.* *See* **Drum.**

Time, *s.* कालः, समयः, वेला. 2 (Occasion) अवसरः, प्रसंगः, प्रस्तावः. 3 वारः, वासरः. 5 अवधिः, मर्यादा. 5 तालः, लयः. 6 (Personified) कालः. 7 (With numerals) गुणं, कृत्वः, वारं, in comp.; '10 t. s' दशकृत्वः; सहस्रगुणं, त्रिवारं, &c.; 'from t. to t.' काले काले; 'losing or wasting t.' कालहरणं कालक्षेपः-हानिः; 'by this t.' अनेन समयेन, इयता कालेन; 'after a long t.' चिरात्, बहोः कालात्; 'for a long t.' चिरं, महांतं कालं; 'of the same t.' समकालीन, समकालिक (की *f.*); 'at the right t.' काले, यथावसरं, प्राप्तकालं; 'in time' यथासमयं-अवसरं, काले; 'in a short t.' अचिरेणात्; 'at the t. when' यदा-तदा; 'at the same t.' समं, एकावसरं, तत्कालं, तत्क्षणं; 'at all t. s.' सदा, सर्वदा; 'at other t.' अन्यदा; 'at t. s.' काले काले, अंतरा अंतरा; 'at this, that, t.' अधुना, तदा; 'at any t.' यदा कदा; 'come at any t.' यदा इच्छसि तदा-यथेष्टकाले-आगच्छ; 'of our, those, t. s' इदानींतन-तदानींतन-(नी *f.*); 'high t.' उचितः समयः; 'it is high t. to bathe and take our meals' समयः स्नानभोजनं सेवितुं (V. 2); 'good for the t. being' आपातरमणीय, आपाततो रम्य; 'hard t. s.' आपत्कालः; विपत्समयः, आपद् *f.*; 'dark t. s.' कलिकालः; 'from t. to t.' अनुवेलं, वारंवारं; 'many t. s' बहुशः, बहुवारं, काले काले; 't.-server', 't.-serving' कालानुवर्तिन्, समयानुरोधिन्; 'I shall not do so next t.' नैवं वारांतरं विधास्यामि; 'what is the t. now' का वेला अधुना वर्तते; 'begging is out of t.' अनवसरग्रस्तोऽर्थिभावः (Mal. 9); 'sign of the t.' कालधर्मः; 'without loss of t.' अकालक्षेपेण, अविलंबितं; 'one keeping or beating t. with the hands' पाणिघः, पाणिवादः; करकिसलयतालैर्मुग्धया नर्त्यमानः (U. 3) 'by keeping t. with her hands' &c.; 'quick, mean, slow, t.' द्रुतं, मध्यं, विलंबितं; 'out of t.' वितालं, वैतालिक (की *f.*). —*v. t.* कालं निर्णी 1 P or परिक्लृप् c., कालानुरूप *a.* कृ 8 U. —**ly,** *a.* Ex. by (*s.*) in comp.; 'showering t.' काल-समय-वर्षिणः; सामयिक (की *f.*); कालकृतोद्योगात् 'by t. attempts.' —*adv.* काले, यथासमयं-कालं.

Timid, Timorous, *a.* भीरु, कातर, ससाध्वस, त्रस्त, सभय, दीन, भीरुहृदय, चकित. —**ity,-ness,** *s.* सं-,त्रासः, कातर्यं, साध्वसं, &c., भीरुता-त्वं, चित्तवैक्लव्यं. —**ly,** *adv.* ससाध्वसं, चकितं, सभयं.

Tin, *s.* त्रपु *n.*, वंगं, रंगं, पिच्चटं; 't.-man' वंग-त्रपु-कारः; 'calx of t' त्रपुभस्मन् *n.*

Tincture, *s.* आभा, छाया, आभासः; ईषन्मिश्रणं-संसर्गः. 2 औषधाधिवासितो मद्यार्कः; निर्यासः, (extract). —*v.* (lit.) ईषद् मिश्र् 10 or अधिवास् 10; (fig.) ex. by (*s.*); 't. ed with truth' सत्याभास.

Tinder, *s.* इंधनं, एधस् *n.*, शीघ्रदाह्यं.

Tine, *s.* शूलः. 2 मृगविषाणशाखा.

Tinge, *s.* रंगः, रागः; आभा, छाया, आभासः; 'speech with a t. of falsehood' असत्याभासं वचनं. —*v. t.* रंज् c. —**ed,** *a.* सराग.

Tingle, *v. i.* रणत्कारं कृ 8 U, रणरणायते (D.), सशूलं स्फुर् 6 P; 'making the ears t.' श्रवणविदारणं (वचः). —*s.* सशूलस्फुरणं, रणरणायितं.

Tinker, *s.* कांस्यकारः.

Tinkle, *v. i.* क्वण् 1 P, शिंज् 2 A, झणझणायते (D.); नि-क्वण् 2 P. —**ing,** *s.* क्वणितं, शिंजितं, झणझणध्वनिः.

Tinsel, *s.* मिथ्याशोभनं वस्तु, बाह्यशोभनं द्रव्यं. —*a.* बाह्यशोभ, कृत्रिमशोभि, मिथ्याशोभन.

Tint, *s.* रागः, रंगः, छाया. —*v. t.* रंज् c.

Tiny, *a.* क्षुद्र, अतिलघु, प्रतनु; 't. spark' तनुप्रकाशः.

Tip, *s.* अग्रं, शिखरं, अग्रभागः, प्रांतः, मुखं, अणि *m. f.*; 't. of the foot' प्रपदं, पादाग्रं; 'learning danced on the t. of his tongue' अमुष्य विद्या रसनाग्रनर्तकी (N. I.), समस्ता एव विद्या जिह्वाग्रेऽभवन् (Ka. 346); 't.-toe' पादाग्रं, प्रपदं, अग्रपादः; 'from head to t.-toe' आपादमस्तकं, नखशिखांतं. —*v. t.* Ex. by अग्र, मुख in comp.; 't. ed with silver' रजताग्र, रजताश्लिष्टकोटि; 't. ed with iron' अयोग्र, लोहाग्र, अयोमुख. 2 Top, q. v. 3 पारितोषिकं दा 3 U. —**s,** *s.* पारितोषिकं.

Tippet, *s.* ग्रैवेयं-यकं, ग्रीवाच्छादनं.

Tipple, *v. t.* अतिपानं कृ 8 U, नित्यशः मद्यं पा 1 P. —**er,** *s.* अतिपानासक्तः, मद्यपः.

Tipsy, *a.* क्षीब, प्रमत्त, मदविकल, मदवश.

Tirade, *s.* आक्षेपः, निंदावचस् *n.*, -लेखः, उपालंभलेखः.

Tire, *s.* उष्णीषः-षं, शिरोवेष्टनं; 't. ing room' नेपथ्यं,-शाला. 2 लोहवलयः-यं. —*v. t.* खिद् c., क्लम् c., श्रम् c.; 'to be t.-ed' क्लम् 1, 4 P, परि-, श्रम् 4 P, आयस् 1, 4 P, खिद् pass., निर्विद् pass., (राज्ञो वयस्यभावेन निर्विण्णोऽस्मि S. 2); See Fatigue. —**ing,-some,** *a.* कष्ट-खेद-कर (री *f.*), आयासक, कष्टावह.

Tissue, *s.* जालं, क्रमः, रचना; 't. of falsehood' अनृतवाग्जालं.

Titan, *s.* दानवः, दैत्यः; *See* **Demon.**

Tithe, *s.* दशांशः, दशमभागः.

Titillate, *v. i. See* **Tickle.**

Title, *s.* नामन् *n*, संज्ञा, लक्षणं, आख्या; *See* **Name;** 't. of honor' उपाधिः, उपपदं, मानपदं, कीर्तिचिह्नं; 'distinguished by the t. of *Sri'kantha*' श्रीकंठपदलांछनः (U. 1). **2** अधिकारः, आगमः, स्वत्वं. **3** उपाधिः, उपपदं. **4** स्थानं, पदं, विषयः; 't.-page' मुखपृष्ठं-पत्रं; 't.-deed' आगमः, -पत्रं. **-Titular,** *a.* नाममात्र; *See* **Nominal.**

Titter, *s.* खच्छहास्यं.

Tittle, *s.* लवः, लेशः, अणुमात्रं.

Tittle-Tattle, *s.* विजल्पितं.

To, *prep.* (With verbs of motion) ex. by acc.; वाराणसीं याति, उमास्थानं जगाम &c. **2** (As indirect object) by dat. of person. **3** (Up to) आ in comp. or with abl., यावत् with acc., अंत-पर्यंत in comp.; 'from one to ten' एकादिदशांताः (संख्याः). **4** (Possession) by gen. **5** (Purpose) by dat. or inf., or अर्थं-र्थे in comp. **6** (Consequence) by circum.; by dat.; 'he was stoned to death' लोष्टघातं हतः, 'he, to my great delight, soon recovered' सोचिरात्सुस्थोऽभवत्तेनाहं प्रमुदितोऽभवम्; 'tortured to death' तथा पीडितो यथा विगतासुरभूत्; 'went to his ruin' स्वनाशायैव जगाम; 'was frightened to death' भीत्या मृतकल्पो बभूव; 'she accompanies the movements of her feet to the musical time' पादन्यासो लयमनुगतः (M. 2), 'to the number of 10' दशसंख्य-*a.*; 'face to face' समक्षं, संमुखं; 'ten to one' प्रायः, भूयसा; भूयिष्ठं; 'take to wife' पत्नीस्थाने मन् 4 A; 'to a man' निःशेषं, अशेषेण; 'to and fro' *adv.* इतस्ततः.

Toad, *s.* मंडूकः. **-y,** *s.* मिथ्याशंसकः.

Tobacco, *s.* तमाखुः.

Tocsin, *s.* भयध्वनिः; भयसूचिका घंटा.

Toddy, *s.* ताली.

Toil, *v. i.* यत् 1 A, श्रम् 4 P, आयस् 4 P. **-s.** श्रमः, आयासः.

Toilet, *s.* प्रसाधनं, मंडनं.

Token, *s.* चिह्नं, लक्षणं.

Tolerate, *v. t. See* **Endure.**

Toll, *v. t.* (घंटां &c.) नद् c., क्वण् c.; *See* **Sound.** **-v. i.** शनैः क्वण् 1 P. **-s.** शुल्कः-ल्कं; करः; 't.-collector' शौल्किकः, शुल्कग्राहिन् *m.*

Tomb, *s.* समाधिः,-स्थानं; 't.-stone' चैत्यं.

Tome, *s.* (ग्रंथस्य) खंडः, भागः.

To-morrow, *adv.* श्वः परेद्युः, परेद्यवि; 'day after t.' परश्वः; 'of t.' श्वस्तन (नी *f.*).

Tomtom, *s.* पटहः, भेरी.

Ton, *s.* शिष्टाचारः. **2** द्रोणः (परिमाणविशेषः).

Tone, *s.* स्वरः, स्वनः, नादः, ध्वनिः, रवः, शब्दः; *See* **Sound.** **2** भावः, चेष्टा, चेष्टितं. **3** (In music) स्वरः; 'long t.' तानः; 'keep a protracted t.' तानं प्रदा 3 U, (उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगंतुं K. 1. 8). **4** (Of body) बलं, आरोग्यं, स्वास्थ्यं, सुस्थता, अग्निः. **-v. t.** (down) मृदूकृ 8 U, स्निग्धीकृ; पारुष्यं अपनी 1 P. **-Tonic,** *s.* बल्यं, वाजीकरणं, बलवर्धनं, अग्निदं, रोचकं, दीपनं; क्षीणबलीयवाजीकरणचिकित्सा 'administering t. s to persons reduced in strength.' **-a.** वाजीकर (री *f.*), बलवर्धन.

Tongs, *s.* कंकमुखं, संदंशः.

Tongue, *s.* जिह्वा, रस(ज्ञ)ना, रसज्ञा; 'hold the t.' *See* **Hold;** 't. of a bell' लोला. **2** वाणी, भाषा; *See* **Language;** 't.-tied' बद्ध-नियंत्रित-जिह्व.

To-night, *adv.* अद्य रात्रौ, नक्तं.

Tonsil, *s.* जिह्वामूलस्थः मांसग्रंथिः.

Tonsure, *s.* क्षौरं, मुंडनं, केशवपनं, चूडासंस्कारः शिरोमुंडनं; 't. ceremony' चौलं.

Too, *adv.* अपि, तथा, चैव. **2** अति in comp.; अत्यंतं, अतीव, भृशं; *See* **Exceedingly;** सुदीर्घ, दीर्घतर 't. long' &c.

Tool, *s.* उपकरणं, साधनं, यंत्रं 'a mere t.' यंत्रमात्रं; 'you are a t. in the minister's hands' त्वं सर्वथा मन्त्रिआज्ञानुवर्ती तेन यंत्रवत् चाल्यसे.

Tooth, *s.* दंतः, दशनः, रदः, रदनः, दंशः. दंष्ट्रा, द्विजः, जंभः; 'two middle fore-teeth' राजदंतौ; 'double teeth' मार्हि *f.* **2** (Of a saw) दंतः; 't.-picker' दंतस्य निष्कोषणं, दंतोल्लेखनी, शोधनी, निर्कर्षकं; 't.-powder' दंतशोधनचूर्णं, दंतपवनं; 't.-brush' दंतधावनं,-कूर्चकं; 'having good teeth' सुदत्; 'in the teeth of' अनादृत्य (with acc.) or by abs. constr.; *See* 'In spite of' under **Spite,** 'in the teeth of the Vedas' वेदेषु जाग्रत्स्वपि सत्सु आप. **-ed,** *a.* दंत, दत् in comp. **-less,** *a.* दंतहीन, गलितदंत, निर्दंत-नीरद, भग्न-उद्धृत-दंष्ट्र. **-some,** *a.* स्वादु. **-Teething,** *s.* दंतोद्भेदः, दंतोद्गमः.

Top, *s.* अग्रं, शिखरं, शृंगं, सानु *m. n.*, शिखा, चूडा, शिरस् *n.*, शीर्षकं, मूर्धन् *m.*, मस्तकं. **2** श्मश्रु. **3** पिधानं, आच्छादनं, पुटं. **4** मुख्यश्रेष्ठ-स्थानं; 'he stands at the t. of the class' सर्वेषां बालकानां मूर्ध्नि तिष्ठति; 't.-

heavy ' उरुर्वगुरु; ' t-knot ' चूडा, शिखा, शिखंड:, शेखर:. –*a*. मुख्य, उपरिस्थ, अग्र in comp.; 't.-most branch,' अग्रशाखा. –*v. t.* Ex. by (*s.*); ' t. ed with snow ' तुहिनावृतशिखर. **2 Excel,** q. v.; *See* (*s.*) also.

Topaz, *s.* पीताश्मन् *m.*, पुष्पराग:.

Tope, *s.* स्तूप:. –*v. i.* मद्यातिपानं कृ 8 U. –**er,** *s.* मद्यासक्त:.

Topic, *s.* विषय:, अर्थ:, प्रस्ताव:; प्रकरणं, वस्तु *n.*

Topography, *s.* स्थानवर्णनं.

Topple, *v. i.* (शिखरात्) सहसा पत् 1 P or अवपत्.

Topsyturvy, *adv.* विपर्यस्त *a.*, अधरोत्तर *a.*

Torch, *s.* उल्का, उल्मुकं, दीपिका, अग्निकाष्ठं.

Torment, *v. t.* (अत्यंतं) अर्द् 1 P or *c.*, पीड् 10, संतप् c., सं-,बाध् 1 A, क्लिश् 9 P, आयस् c., विप्र-कृ 8 U, प्रमंथ् 9 P; *See* **Afflict.** –*s.* (अत्यंत-) आतंक:, संताप:, व्यथा, पीडा, दु:खं, वेदना, यातना; कारणा, दारुण-तीव्र-तिग्म-यातना-वेदना. –**ing,** *a.* प्रमाथिन्, अरुंतुद, आयासकारिन्. –**or,** *s.* अतिपीडक:, प्रमाथिन् *m.*, आयासक:, संतापक:.

Tornado, *s.* घूर्णवायु:.

Torpid, *a.* जड; सुप्त, विचेतन. **2** मंद, जड; *See* **Dull, Slow.** –**ity, Torpor,** *s.* जाड्यं, सुप्ति *f.*, चैतन्यनाश:, स्वाप:, मांद्यं, तंद्रा, जडिमन् *m.*

Torrent, *s.* स्रोतस् *n.*, रय:, वेग:, ओघ:. **2** जलप्रवाह:-प्रपात:, निर्झर:, प्रस्रवणं; नदी. **3** धारा, आसार:; 't. s of rain ' धारासंपात:, धारासार:, वृष्टिधारा; धारासारैर्महती वृष्टिर्बभूव 'it rained in t. s'.

Torrid, *a.* उष्ण; *See* **Hot.**

Tortoise, *s.* कूर्म:, कमठ:, कच्छप:; ' female of a t. ' कूर्मी, कमठी, डुलि:.

Tortuous, *a.* वक्र, कुटिल, जिह्म, तिर्यञ्च्. –**ly,** *adv.* वक्रं, तिर्यक्-कुटिल in comp.

Torture, *v. t.* यत् c., अत्यंतं पीड् 10, प्रमंथ् 9 P; *See* **Torment.**

Toss, *v. t.* उत्-वि-क्षिप् 6 P, व्युदस् 4 U. उद्-धू 5, 9 U, संक्षुभ् c.; *See* **Throw.** –*v. i.* विक्षिप्-उद्धू-pass., इतस्तत: विचल् 1 P or लुट् 6 P or लुल् 1 P or प्लु 1 A, घूर्ण् 6 P, 1 A. –*s.* उत्-क्षेप:-पर्ण; स-क्षोभ:.

Total, *a.* सकल, सर्व, समग्र, संपूर्ण, &c.; *See* **Whole;** ' t. rout ' अत्यंतनाश:, सुपलायितं; ' t. disorder' अत्यंतमाकुलं. –**ity.** *s.* साकल्यं, समष्टि *f.*, ऐक्यं, कार्त्स्न्यं; ' what is the t. ' एवं सर्वे (पिंडीकृत्य) कति संपद्यंते. –**ly,** *adv.* संपूर्णं, साकल्येन, सर्वथा-श:, अशेषेण, नि:शेषं.

Totter, *v.* प्र-,स्खल् 1 P, कंप् 1 A, वि-चल् 1 P; *See* **Shake.** –**ing,** *a.* स्खलित, स्खलित-विह्वल-गति.

Touch, *v. t.* सं-,स्पृश् 6 P, (fig. also); परामृश् 6 P, हस्तेन आलभ् 1 A; ज्ञातसंख्या तु मामियं स्पृशति (Ve. 2) ' t. es me home '; ' was t. ed to the heart ' हृदये (दिग्धशरेणेव) आहत: (R. v. 25); 'heart t. ed with anxiety' हृदयं संस्पृष्टमुत्कंठया (S. 4). **2** (On, upon) उद्दिश्य-अधिकृत्य-वद् 1 P ('Say ', q. v.). –*v. i.* संसर्ग-संपर्क-इ 2 P or गम् 1 P. –*s.* सं-, स्पर्श:-र्शनं, परामर्श:, आलंभनं, संसर्ग:, संपर्क:. **2** स्पर्शबोध:-ज्ञानं. **3** स्पर्श:, स्पर्शेंद्रियं; ' t.-stone ' नि-,कष:, निकषग्रावन् *m.*-पाषाण:-उपल:, शाण:; ' adversity is the t.-stone of (the sincerity of) friendship' सेवा (मित्राणां) सत्त्वनिकषग्रावा विपत् (H. 1.). –**ing,** *prep.* उद्दिश्य, अधिकृत्य; *See* **About.** *a.* हृदयंगम, हृदिस्पृश्; *See* **Pathetic.** –**y,** –*a.* कोपन, चंडकोप, शीघ्र- सुलभ-कोप.

Tough, *a.* कठिन, दृढ, दुर्भेद्य.

Tour, *s.* परि-भ्रमणं, पर्यटनं; ' he is on t. ' स्वमंडले चरति-भ्रमति; ' make a t. ' परिभ्रम् 1, 4 P. –**ist,** *s.* पर्यटक:.

Tournament, *s.* सादिक्रीडा-युद्ध.

Tow, *v. t.* कृष् 1 P, आकृष्य संचल् *c.* –*s.* स्थूलशाणं, शणसूत्रं.

Toward, Towards, *prep.* प्रति (with acc.), अभि in comp.; by अभिमुख-*a.* (खी *f.*) or अभिमुखं-*adv.* in comp., (गृहाभिमुखं प्रतस्थे), उद्दिश्य (with acc.). **2** (With words of direction) by loc. also, उपरि (with gen.); ' t. the north ' उत्तरस्यां दिशि, उत्तराभिमुखं; ' t. me ' ममोपरि, मां प्रति, मामुद्दिश्य. मयि. **3** प्राय:; ' t. evening' अभिसायं, सायाह्नकल्पं. –*a.* *See* **Forward;** 'un-t' अतर्कित, अप्रमार्षितोपगत.

Towel, *s.* गात्रमार्जनी, मार्जनवस्त्र.

Tower, *s.* अट्ट:, उत्सेध:; क्षौम:-मं (room on the t.). –*v. i.* मूर्ध्नि वृत् 1 A or स्था 1 P. –**ing,** *a.* प्रोन्नत, प्रांशु-उत्तुंग.

Town, *s.* पुरं, पुर् *f.*, पुरी, नगरं-री, पत्तनं (small t.), पुटभेदनं, स्थानीयं, निगम:. –**Townsman,** *s.* नागरिक:, पौर:,-जन: (पौरी, पौरवधू *f.*).

Toxic, *a.* विषसंबंधिन्. –**ology,** विषविद्या.

Toy, *s.* क्रीडनकं, क्रीडाद्रव्यं-वस्तु. –*v. i.* क्रीड् 1 P; *See* **Play.**

Trace, *s.* चिह्नं, अंक:, अभिज्ञानं; *See* **Mark. 2** (Of foot-steps) पदवी, पद्पद्धति *f.*; *See* **Footstep. 3** (Of carts) प्रग्रह:, चर्मबंध:. –*v. t.* आलिख् 6 P, बाह्य

रेखां लिख्. 2 अनु-सृ 1 P, अनु-धाव् 1 P; मृग् 10 A, अनुपदं या or व्रज्. 3 (Out) आ-साद् c., ज्ञा 9 U, समुत्केऽर्जिते चौरो लोप्त्रेणाथ पदेन वा (Y. II. 266) 'or is t. ed out' &c.; oft. by प्रभव: ('Source' q. v.) 'his sudden affluence has been t. ed out' तस्याकस्मिकविभूतेः प्रभव उपलब्धः. 4 (Word) व्युत्पद् c.; 'when the word *Brahman* is t. ed (to its root); ब्रह्मशब्दस्य व्युत्पाद्यमानस्य. (S. B ३३).

Trachea, *s.* श्वास-वाय-मार्गः.

Track, *v. t.* अनु-सृ 1 P, अनु-धाव् 1 P, मार्ग् 10; *See* **Follow**. —*s.* मार्गः, पदचिह्न-पंक्ति *f.*; *See* **Way**. 2 चिह्नं, अंकः. **-less**, *a.* निःसंचार, निर्जन, पादास्पृष्ट.

Tract, *s.* प्र-,देशः, भूभागः. 2 प्रबंधः, ग्रंथः, लघुलेखः-ग्रंथः.

Tractable, *a.* विधेय, विनीत; वश्य; *See* **Docile**.

Traction, *s.* कर्षणं, वहनं.

Trade, *s.* वाणिज्यं, वणिक्कर्मन् *n.*, व्यापारः, क्रयविक्रयः. 2 व्यवसायः, व्यवहारः, वृत्ति *f.*, व्यापारः. —*v. i.* वाणिज्यं कृ 8 U, व्यव-हृ 1 P, पण् 1 A, क्रयविक्रयं कृ; oft. by (*s.*); 'went out to t.' वाणिज्येन गतः; 't. ing by sea' समुद्रव्यवहारी (S. 6). **-er**, *s.* वणिज् *m.*, वाणिज्यकारिन्; *See* **Merchant**. **-Tradesman**, *s.* पण्यविक्रयिन् *m.*

Tradition, *s.* संप्रदायः, आम्नायः. 2 ऐतिह्यं, लोककथा, पारंपरीयकथा, पारंपर्यं; 'there runs a t. to this effect' इति ऐतिह्यं. **-al, -ary**, *a.* परंपरागत-प्राप्त, परंपरीण, क्रमागत-आयात, सांप्रदायिक-पौराणिक- (की *f.*); 't. knowledge' संप्रदायः, (कुमारस्य पुनः कुतः संप्रदाय इति पृच्छामि U. 6). **-ally**, *adv.* संप्रदायतः, पारंपर्येण.

Traduce, *v. t.* आक्षर् c., अभिशंस् 1 P, अप-परि-वद् 1 A; *See* **Calumniate**. **-er**, *s.* आक्षारकः, अपवादकः.

Traffic, *See* **Trade**.

Tragedy, *s.* शोकपर्यवसायि नाटकं. **Tragic, -Tragical**, *a.* शोकपर्यवसायिन्, दुरंत. 2 करुणरसप्रधान.

Trail, *s.* पंथः. 2 पद्धती, पादचिह्नं, पदं. —*v. t.* वि-आ-कृष् 1 P; *See* **Drag**. —*v. i.* कृष् pass.

Train, *s.* परंपरा, श्रेणी, माला; *See* **Series**. 2 परिवारः, परिबर्हः, परिजनः. 3 (Of dress) पुच्छं, वसनांतः. 4 परिपाटी, अनु-,क्रमः; प्रबंधः; 't. of reasoning' ऊहक्रमः, तर्कप्रबंधः, t. of a peacock' बर्हः, पुच्छं. —*v. t.* वि-नी 1 P, (animal also), अभि-वि c. (अभ्यापयति); अनु-,शास् 2 P, शिक्ष् c.; दम् c. (दमयति). 2 परिचर्य-अभ्यासं-कृ c.; 'a t. -ed soldier' कृतश्रमपरिचयः पदाती. **-ing**, *s.* शिक्षा, विनयः-यनं; शिक्षणं, अभ्यासः; 'military t.' रण-अस्त्र-शिक्षा, युद्धाभ्यासः.

Trait, *s.* लक्षणं, चिह्नं.

Traitor, -ous, *s.*, *a.* विश्वास-विश्रंभ-घातिन्, मित्रघातिन्, शत्रु-द्विड्-सेविन्; 't. to the king' राजापकारिन्, राजद्रोहिन्; 't. to the country' स्वदेशशत्रु-घातकः; 'act the t.' द्रुह् 4 P.

Trammel, *See* **Fetter**.

Tramp, *v. i.* चरणं-पादं-न्यस् 4 P or क्षिप् 6 P. —*s.* पादशब्दः, चरणविक्षेपः.

Trample, *v. t.* मृद् 9 P, सं-अव-°, अभि-हन् 2 P; (under foot) पादतलेन आहन् 2 U or आ-समा-क्रम् 1 U, 4 P or क्षुद् 7 P; 't. to dust' चूर्ण् 10, निष्पिष् 7 P. **-ed**, *a.* सं-अव-मर्दित, पादतलाहत, पादाक्रांत; पादक्षुण्ण. **-ing**, *s.* मर्दनं, पादाघातः, पादाक्रमणं, प्रमथनं.

Trance, *s.* समाधिः, लयः, तन्मयावस्था, देहातीतवृत्ति *f.*, 'being in a t.' लीनवृत्ति, समाधिस्थ.

Tranquil, *a.* प्र-, शांत, स्तिमित, निश्चल, स्वस्थ, अक्षुब्ध, शांतात्मन्; *See* **Calm**. **-lity**, *s.* शमः, शांति *f.*, प्र-,उप-°, अक्षोभः, निर्वृति *f.*, निरुपद्रवत्वं, धैर्यं, अनुद्वेगः, स्वास्थ्यं, स्थैर्यं. **-lize**, *v. t.* शां(सां)त्व् 10, शम् c. (शमयति), प्र-उप-°, आ-समा-श्वस् c.; *See* **Calm, Compose**; 't. yourself' समाश्वसिहि.

Transact, *v. t.* सं-निः-पद् c., साध् 5 P or c., वि-धा 3 U, कृ 8 U, अनु-ष्ठा 1 P; निर्वह् c., प्रवृत् c., आ-समा-चर् 1 P; (a business) व्यव 1 A, व्यव-हृ 1 P. **-ion**, *s.* करणं, अनुष्ठानं, विधानं, निर्वाहः, आचरणं &c. 2 कार्यं, कृत्यं, कर्मन् *n.*, व्यापारः, व्यवहारः, घटना.

Transcend, *v. t.* अति-इ 2 P. अति-शी 2 A; अतिक्रम् 1 U, 4 P; *See* **Excel**; 't. s. definition' अपरिच्छेद्य, परिच्छेदातीत; 't. a description' सकलवचनानामविषयः (Mal. 1), वर्णनविषयातिक्रांतः; *See* **Pass**. **-ent, -ental**, *a.* सर्वातिरिक्त, सर्वातिशायिन्, अत्युत्तम. **-ently**, *adv.* सविशेषं, परमं, अत्युत्तमं.

Transcribe, *v. t.* लिख् 6 P. **-er**, *s.* लिपिकारः; लेखकः. **-Transcript**, *s.* प्रतिलेखः, प्रति-,लिपि *f.*

Transfer, *v. t.* स्थानांतरं नी 1 P or वह् c. 2 सं-क्रम् c (with loc. for 'to') संचर् c., ऋ-अर् c. (अर्पयति), निक्षिप् 6 P, अध्यारुह् c.; तनयेषु तद्धुरं संक्रमय्य (Ks. 345), (कृतसंक्रांतलक्ष्मीकैः U. 1). **-ence**, *s.* स्थानांतरप्रापणं-नयनं, स्वाम्य-स्वत्व-परिवृत्ति,

f. **2** संक्रांति *f.*, संक्रमणं, संचारः, परहस्तसमर्पणं.

Transfigure, *v. t. See* **Transform.**

Transfix, *v. t.* व्यध् 4 P, निर्भिद् 7 P. **2** अचलीकृ 8 U, कील् 10, निखन् 1 P, कीलितेव चास्मिन्नेव स्थाने तनुः (Ka. 278) 'as if t.-ed to this very spot'; 't.-ed through the belly' निर्भिन्नोदर.

Transform, *v. t.* परिणम् c. (परिणमयति), रूपांतरं वि-धा 3 U, आकारं-रूपं-परिवृत् c.; 'to be t.-ed' परिणम् 1 U, रूपांतरेण परिणता &c. (V. 4.). **2** विडंब् 10, विकृ 8 U. **-ation,** *s.* रूपांतरपरिणामः, परिवर्तः, रूपांतरं, विकृति *f.*, विडंबनं.

Transfuse, *v. t.* अन्यपात्रे संक्रम् c. or निविश् c., **-ion,** *s.* संक्रामणं.

Transgress, *v. t.* वि-,अतिक्रम् 1 U, 4 P, अति-इ 2 P, उद्-,लंघ् 1 A, 10, भंज् 7 P; व्यभि-अति-चर् 1 P, अतिवृत् 1 A, लुप् 6 P or c. **-***v. i.* अप-,राध् 4 P (with loc. of person); *See* **Offend.** **-ion,** *s.* अतिक्रमः, उल्लंघनं, व्यतिक्रमः, अत्याचारः, अत्ययः, भंगः, लोपः, अतिपातः. **2** अपराधः, दोषः, पापं. **-or,** *s.* अतिक्रामिन्, अत्याचारिन्, अपराधी.

Tranship, *v. t.* वाहन-यान-अंतरं नी 1 P.

Transient, *a.* चंचल, लोल, क्षणभंगुर, अचिरस्थायिन्, अस्थायिन्, चपल, विनश्वर, अनित्य, क्षणिक, असार, अशाश्वत (ती *f.*), क्षणविध्वंसिन्. **-ness,** *s.* अनित्यता, अस्थायित्वं.

Transit, *s.* क्रांति *f.*, संक्रमः. **-ion,** *s.* संक्रांति *f.*, परिवर्तः, विकारः; (state) स्थित्यंतरं, अवस्थांतरं. **-ive,** *a.* सकर्मक. **-ory,** *a.* क्षणभंगुर, असार; *See* **Transient.**

Translate, *v. t.* भाषांतरेण वि-परिणम् c. or परिवृत् c.; 'boys should t. Sanskrit sentences into English' बालकाः संस्कृतवाक्यानि आंग्लभाषया विपरिणमयेयुः. **2** **Transform,** q. v. **3** (To the skies) (सशरीरं) लोकांतरं नी 1 P or प्राप् c. or गम् c., 't.-ed to the skies' सशरीरस्वर्गतः. **-ion,** *s.* विपरिणामः, विपरिणमनं, भाषांतरं, अनुवादः. **2** लोकांतरनयनं, स्वर्गारोपणं, सशरीरमुक्ति *f.* **-or,** *s.* भाषांतरकृत् *m.*

Translucent, *a. See* **Clear.**

Transmigrate, *v. i.* पुनर्जन्म प्राप् 5 P, देहांतरं गम् 1 P. **-ion,** *s.* पुनर्जन्मन् *n.*, पुनर्जननं, देहांतरप्राप्ति *f.*-गमनं, योन्यंतरं.

Transmit, *v. t. See* **Send, Remit.** **-Transmission,** *s.* प्रापणं, वाहनं, प्रेषणं, संचारणं.

Transmute. *v. t. See* **Change, Transform.**

Transparent, *a.* शुद्ध, स्वच्छ, प्रसन्न, विशद, निर्-वि-अ-मल, स्फटिकसम. **2** प्रकाश-किरणभेद्य, पारदर्शिन्. **-Transparency,** *s.* स्वच्छता, प्रसादः, नैर्मल्यं, &c.

Transpire, *v. i.* प्रकाशतां गम् 1 P, प्रकाशी-प्रकाशि-भू 1 P, (कथं प्रकाशतां गतोऽयमर्थः परेषु Mu. 1), प्रसिद्धीभू, निः-प्र-सृ 1 P.

Transplant, *v. t.* स्थानांतरे रुह् c.

Transport, *v. t.* नी-वह्-1 P; हृ c. **2** द्वीपांतरे निर्वस् c. or विवस् c., स्वदेशात् दूरीकृ 8 U. **2** अत्यंतं प्रहृष् c.; 'Delight' excessively, q. v.; 't.-ed with joy' हर्षनिर्भर, आनंदस्य परां कोटिं गत. **-s.** नयनं, वाहनं. **2** प्रवहणं. **3** हर्षोन्मादः, हर्षनिर्भरः; हर्षावेशः.

Transpose, *v. t.* विपर्यस् 4 U, स्थानं परिवृत् c., विनि-मे 1 A; *See* **Exchange.** **-ition,** *s.* (स्थान-) व्यत्ययः, व्यत्यासः, विनिमयः, विपर्यासः, परिवृत्ति *f.*

Transverse, *a.* व्यत्यस्त, तिर्यक्; 'with legs t.' व्यत्यस्तपाद्-*a.* **-ly,** *adv.* व्यत्यासेन, तिर्यक्, व्यत्यस्तं.

Trap, *s.* उन्माथः, कूटयंत्रं, कूटं; 't.-door' कूटद्वारं, छन्नमार्गः. **-***v. t.* कूटे निक्षिप् 6 P. **2** भूष् or मंड् 10.

Trapezium, *s.* अतुल्यलंबकः.

Trapezoid, *s.* समलंबकः.

Trappings, *s.* सज्जा, भूषा, परिकर्मन् *n.*, परिच्छदः; 't. of an elephant' परिस्तोमः, आदानं; *See* **Housings.**

Trash, *a.* असार, निरर्थक, निःसार. **-s.** असार-निरर्थक-द्रव्यं.

Travail, *See* **Lobour.**

Travel, *v. i.* परि-भ्रम् 1, 4 P, परि-,अट् 1 P, विचर् 1 P; *See* **Journey.** **-s.,-ling,** *s.* पर्यटनं, परि-,भ्रमणं, विचरणं, यात्रा, प्रवासः, अध्वगमनं. **-ler,** *s.* पांथः, पथिकः, अध्वगः, अध्वनीनः, अध्वन्यः, यात्रिकः, पाथिकः, सारणिकः.

Traverse, *v. t.* आक्रम् 1 U, 4 P, तॄ 1 P, सं-अति-उत्-°, पारं गम् 1 P.

Tray, *s.* भाजनं, आधारः, पात्रं.

Treachery, *s.* विश्वासभंगः-घातः, विश्रंभभंगः, असत्यसंधता, प्रतिज्ञा-समय-भंगः; *See* **Perfidy.** **-ous,** *a.* विश्वासघातिन्, अविश्वास्य, असत्यसंध. **2** मिथ्याभास, असार, मायाबहुल. **-ously,** *adv.* विश्वासघातेन, शाठ्येन. **-ousness,** *s. See* (*s.*).

Treacle, *s.* गुडः; *See* **Molasses.**

Tread, *v.* क्षुद् 7 P, आ-समा-क्रम् 1 U, 4 P. पादाभ्यां पीड् 10 or आक्रम् or मृद् 9 P; 'from the trodden path' क्षुण्णाद्वर्त्मनः, (क्षुद्रजनक्षुण्ण एष मार्गः Ks. 146); 'trod one of them to death' तेषामेकतमः

पादाक्रांतोऽम्रियत, एकं पादतलेन अवाक्रुन्दात; 't. in the footsteps of ' पदं अनुवि-धा 3 U, पदवीं प्रतिपद् 4 A, (पदवीं तरुवल्कवाससां प्रपेदिरे R. viii. 11). 2 क्रम्, पदं-चरणं-विन्यस् 4 P or ऋ c. (अर्पयति). -s. चरणपातः, पादन्यासः-विक्षेपः, विक्रमः.

Treason, s. राजद्रोहः, राजाभिद्रोहः-अपकारः, राजापथ्यकारित्वं. **-able,-ous,** a. राजद्रोहिन्, राजापथ्यकारिन्.

Treasure, s. कोशः-षः, निधिः निधानं, द्रव्यसंचयः-राशिः-संग्रहः. 2 वित्तं, धनं, भांडं, द्रविणं; *See* **Wealth.** -v. t. सं-चि 5 U राशीकृ 8 U, नि-उप-धा 3 U; *See* **Sto.** 't. in the heart ' हृदि उप-नि-धा, अवधृ 10, चित्ते कृ. **-er,** s. कोशाध्यक्षः-अधीशः, कोषगृहे नियुक्तः. अर्थाधिकारिन् m., धनाध्यक्षः, कनकाध्यक्षः, भौरिकः (gold t.); रूप्याध्यक्षः, नैष्किकः (silver t.). **-y,** s. कोषागारं, कोशः-षः, भांडागारं, कोशगृहं.

Treat, v. t. Ex. by ' Act' (towards) q. v., पुत्रे मित्रवदाचरेत् 'should t. a son like a friend '; 't. your rivals as dear friends ' कुरु प्रियसखीवृत्तिं सपत्नीजने (S. 4). 't. with honour ' पूज् 10, पुरस्कृ 8 U, सत्कृ, मन्त्र् 1 A; *See* **Honour;** 't. hospitably ' आतिथ्यं कृ, अतिथिसत्कारं कृ. 2 (A subject) निरूप् 10, विचर् c., वर्ण् 10, प्र-स्तु 2 U, 't. at length ' प्रपंचयति (D.). 3 उप-उपा-चर् 1 P, कित् desid (चिकित्सति-ते). 4 संतृप् c., 'gave a good t. ' भोजनविशेषैः संतर्पयांचकार; 't. with ' सं-धा 3 U. -s. भोजनविशेषः, उत्तमाशतर्पणं. **-ment,** s. आचरणं, व्यवहारः, वृत्ति f., आचारः, नयः; 'ill-t.' अपकारः, अपक्रिया. 2 चिकित्सा, उपचारः, उपक्रमः. 3 वर्णनं-ना, निरूपणं, विवेचनं, विचारणा **-y,** s. संधिः, संधानं. 2 संधिपत्रं, नियम-समय-पत्रं.

Treatise, s. नि-प्र-बंधः, लेखः.

Treble, a. त्रिगुण, त्रिविध. -s. (In music) तारः; उच्चस्वनः. -v. t. त्रिगुणीकृ 8 U. **-Trebly,** adv. त्रिगुणं, त्रिधा, त्रेधा.

Tree, s. वृक्ष , तरुः, द्रुमः, पादपः, वनस्पतिः, शाखिन् m., अनोकहः, विटपिन् m., कुटः, सालः, पलाशिन् m., द्रुः, अगमः, अगः; and रुह-ज with 'Earth' q. v., क्षिति-मही-पृथिवी-रुहः-ज m. &c.

Trefoil, a. त्रिपर्ण, त्रिदल.

Trellis, s. जालं, गवाक्षजालं.

Tremble, v. i. वि-त्रस् 1, 4 P, (with fear) प्र-वेप् 1 A, कंप् 1 A, स्फुर् 6 P, प्र-वि-°, स्पंद् 1 A; प्र-वि-चल् 1 P. **-ing,-Tremulous,** a. कंपमान, वेपथुमत्, सकंप, तरल, विलोल, चपल, चंचल; उत्त्रस्त, कातर (with fear); भग्न, गद्गद (voice); 'in a t. voice ' स्वरभंगेन, सगद्गदं. **-Tremor,** s. प्र-कंपः, साध्वसं, वेपथुः, वेपनं, स्फुरणं, उत्त्रासः, कातरता, &c.

Tremendous, a. महाप्रमाण, अतिबृहत्; घोर, दारुण, अतिगुरु.

Trench, s. खातं, परिखा, नाली, प्रणाली; आलवालं (of a tree). -v. t. खन् 1 P; 't. upon ' आक्रम् 1 U, 4 P; *See* **Encroach.** **-er,** s. खनकः. 2 काष्ठपात्र-भाजनं.

Trend, वृत्ति f.. भावः.

Trepidation, s. उद्वेगः, संक्षोभः, साध्वसोत्कंपः, भयकंपः.

Trespass, v. अति-उत्-क्रम् 1 U, 4 P, अतिचर् 1 P, अनधिकारं प्रविश् 6 P; *See* **Transgress, Intrude, Offend.** -s. अतिक्रमः, मर्यादातिक्रमः अमर्यादा, अपराधः, दोषः.

Tress, s. कबरी, केशकलापः; अलकः, चूर्णकुंतलः.

Triad, s. त्रिकं, त्रयं, त्रितयं.

Triangle, s. त्रिभुजः, त्रिकोणः, त्र्यस्रं. **-Triangular,** a. त्रिकोण, त्र्यस्र, त्रिभुजाकार, त्रिकोणाकृति.

Tribe, s. जाति f.: वर्गः, वर्णः (caste).

Tribulation, s. दुःखं, क्लेशः, कष्टं; *See* **Distress.**

Tribunal, s. [illegible]-आसनं, व्यवहारासनं; 'sat on the t. ' व्यवहारासनमाददे. 2 धर्म-न्याय-सभा.

Tribute, s. करः, शुल्कः-ल्कं; (fig.) उपहारः; *See* **Present.** **-ary,** a., s. करद; सामंत; 'rendered t. ' करदीकृत. 2 (Of a river) शाखा.

Trice, s. *See* **Twinkling.** 2 रज्ज्वा बंध् 9 P or कृष् 6 P.

Tricentenary, s. त्रिशताब्दं. 2 त्रिशताब्दतिथि m. f.

Trick, s. छलं, छद्मन् n., कपटं, कूटोपायः-कल्पना-प्रबंधः, अप-व्यप-देशः, व्याजः, कैतवं. 2 माया, हस्तलाघवं (juggler's t.). 3 कुचेष्टा, चेष्टितं; लीला, खेलनं, दुर्ललितं. -v. t. वंच् 10, प्र-लभ् c.; *See* **Cheat.** **-ery,** s. *See* **Deceit.** **-ster,** s. वंचकः, कितवः, प्रतारकः.

Trickle, v. i. मंदं मंदं स्रु 1 P, परि-स्रु, कणशः शनैः शनैः-क्षर् 1 P or स्यंद् 1 A.

Trident, s. त्रिशूलं; त्रिशिखं, त्रिशीर्षकं पिनाकः,-कं (of Siva).

Triduan, a. त्र्याहिक (-की f.).

Triennial, a. त्रैवार्षिक (-की f.)

Trifle, *v. i.* बालकवत् आचर् 1 P or वृत् 1 A; खेल् P; 't. with' परिहस् 1 P; *See* **Jest** 't. away' अव-,क्षिप् 6 P; *See* **Spend.** –*s.* अणुः, लेशः,लवः. 2 अल्प-स्वल्प-विषयः लघ्वर्थः. –**ling,** *a.* लघु, निरर्थक, तुच्छ, क्षुद्र, लघ्वर्थ, सु-,अल्प, तृणप्राय, अकिंचित्कर (री *f.*).

Trifoliate, *a.* त्रिदल, त्रिपर्ण.

Trigonometry, *s.* त्रिकोणमिति *f.*

Trilateral, *a.* त्रिभुज, त्रिपार्श्व.

Triliteral, *a.* त्र्यक्षर.

Trill, *s.* स्वरकंपः. –*v. i.* कंप् 1 A (Said of voice).

Trillion, *s.* दशपरार्ध.

Trim, *v. t.* क्लृप् c., वि-,रच् 10,परिष्कृ 8 U. –*a.* क्लृप्त, सु-,रचित, विनीत, परिष्कृत. –*s.*, **ming,** *s.* परिकल्पः, भूषा-षणं, सज्जा; 'the body is not in good t.' शरीरमस्वास्थ्यं (Mal. 1). 2 अवस्था, दशा.

Trinity, *s.* त्रिमूर्ति *m.*

Trinket, *s.* कंकणः-णं; अलंकारः; *See* **Ornament.**

Trinomial, *a.* त्रिपद.

Trio, *s.* त्रयी, त्रयं, त्रितयं, त्रिकं.

Trip, *v. i.* प्र-,स्खल् 1 P; वि-,भ्रम् 1, 4 P, वि-चल् 1 P. 2 लघु चल्-र् 1 P. –*v. t.* प्र-,स्खल् c. –*s.* स्खलितं स्खलनं, भ्रमणं, पर्यटनं.

Tripartite, *a.* त्रिभाग, त्रिखंड.

Tripe, *s.* जठरं, उदरं; अंत्राणि (pl.).

Triped, *s.* त्रिपदी.

Triple, *a.* त्रिगुण, त्रिविध, त्रिधा-त्रेधा *ind.* –*v. t.* त्रिगुणीकृ 8 U. –**Triplicate,** *a.* त्रिगुण, त्रिरावृत. –*s.* तृतीयः प्रतिलेखः. –**Triplicity,** *s.* त्रैविध्यं, त्रैगुण्यं.

Tripod, *s.* त्रिपदं आसनं.

Trisect, *v. t.* समं त्रिधा विभज् 7 P.

Trisyllable, *s.* त्र्यक्षरं, त्रिकं.

Trite, *a.* क्षुण्ण, जीर्ण, उच्छिष्ट, सुप्रसिद्ध, सदाव्यवहारित.

Triturate, *v. t.* संघृष् 1 P, निष्पिष् 7 P: *See* **Grind.**

Triumph, *v. i.* वि-परा-जि 1 A, प्रगल्भ् 1 P. 2 विजयोत्सवं कृ 8 U. –*s.* वि-,जयः. 2 विजयोत्सवः, जययात्रा. 3 जयहर्षः-उल्लासः; आनंदहेतुः. –**al,** *a.* जय in comp.; जयतोरणं 't. arch'; 't. column' जयस्तंभः. –**ant,** *a.* जैत्र (त्री *f*), जयशालिन्, जेतृ, जिष्णु, वि-,जयिन्, प्राप्तजय, क्षतारि –**antly,** *adv.* सजयं, सजयघोषं.

Triumvirate, *s.* त्रिनरप्रभुत्वं.

Trivial, *a.* *See* **Trifling.**

Troll, *v. i.* परि-भ्रम् 1,4 P. –*s.* *See* **Goblin.**

Troly (ey) हस्तचाल्यं यानं.

Troop, *s.* (T. s) सैनिकाः, पदातयः, सैन्यं; *See* **Force.** 2 गुल्मः-ल्मं, कुलं. 3 यूथ, गणः, कदंबः, वृंद, कुलं; *See* **Herd.** –**er,** *s.* सादिन् *m.*, अश्वारोहः.

Trope, *s.* रूपकं.

Trophy, *s.* जयस्तंभः-चिह्नं.

Tropic, *s.* अयनवृत्तं, क्रांतिवलयं-मंडलं. –**al,** *a.* Ex. by (*s.*) in comp.

Trot, *s.* धो(धौ)रितं-तकं. –*v. i.* धोरितेन या 2 P or भ्रम् 1 P.

Troth, *s.* विश्वासः, प्रत्ययः; 'by my t.' सत्यमेव, यदि तव मयि विश्वासः.

Trouble, *s.* कष्टं, दुःखं, पीडा, क्लेशः, प्र-आयासः, खेदः, कृच्छ्रं; आ-वि-पद् *f.*, दुर्दशा, बाधा, उपरोधः. 2 यत्नः, उद्यमः; *See* **Pains.** 3 कंटकः, आयासकः, शल्यं. –*v. t.* बाध् 1 A, पीड् 10, क्लिश् 9 P, उपरुध् 7 U, आयस् c., सं-परि-तप् c.; *See* **Afflict;** 't.-ed at heart' खिन्नांतःकरण, उद्विग्नचित्त and sim. comp.; 'Oh ! do not t. yourself' अलमात्मानमायास्य, कृतं कृतं आयासेन. –**ed,** *a.* बाधित, पीडित &c., व्यग्र, उद्विग्न, कातर, विह्वल, आर्त, विक्लव. –**some,** *a.* कष्ट-पीडा-कर (री *f.*), पीडाप्रद, क्लेशावह, दुःखावह, दुष्ट, आयासहेतुक; 'a t. fellow' कंटकः. –**Troublous,** *a.* क्षुब्ध, सोपद्रव.

Trough, *s.* द्रोणि-णी *f.*

Trounce, *v. t.* *See* **Whip.**

Troupe, *s.* संघः.

Trow, *v. t.* श्रद्-धा 3 U. प्रति-इ 2 P.

Trowel, *s.* कर्णी *f.*

Trowsers, *s.* जंघात्राणं-वस्त्रं.

Truant, *a.* कार्यपराङ्मुख (खी *f.*); अलस; 'to be t.' अलसवत् आचर् 1 P.

Truce, *s.* युद्धविश्रामः, युद्धनिवृत्ति *f.*, अवहारः; 't. to' ex. by विरम् 1 P, अलं (with instr.): 't. to your jest' अलं परिहासेन 't. to your impudence' विरमातिप्रसंगात् (U 5).

Truck, *s.* शकटः-टं; *See* **Cart.**

Truckle, *v. i.* *See* **Flatter.**

Truculent, *a.* क्रूर, निष्ठुर, निर्दय.

Trudge, *v. i.* शनैः-मंदं-व्रज् or चल् 1 P. पद्भ्यां चल्.

True, *a.* सत्य, तथ्य, अवितथ, ऋत, यथार्थ, वास्तविक (की *f.*), सत् pr.; अकृत्रिम, अकृतक (not feigned). 2 युक्त, उपपन्न; 'what you say is t.' युक्तं आह भवान्; 't. to one's engagements' सत्यसंध-प्रतिज्ञ-व्रत. –**ly,** *adv.* सत्यं, वस्तुतः, यथार्थतः, परमार्थतः, तत्त्वतः; 'affection t. so called' परमार्थतः, प्रेम; 'Parantapa t. so called' परंतपो नाम यथार्थनामा (R. vi. 21); भुवसिद्धेरपि यथार्थनाम्नः सिद्धिं न मन्यते (M. 4) 'true to his name', 't. so called.' –**Truism,** *s.* सत्यं, स्वतः-

सिद्धवचनं. -**Truth,** *s.* सत्यं, सत्यं, अवितथं, ऋतं, तत्त्वं, भूतार्थः, परमार्थः; तत्त्वार्थः. 2 सत्यता, यथार्थता, याथार्थ्यं; 'in t.' सत्यमेव, खलु, नूनं; 'to tell you the t.' यत्सत्यं, वस्तुतः. -**ful,** *a.* सत्य; *See* (*a.*). 2 (Of persons) सत्यवादिन्, यथार्थवक्तृ-वादिन्, ऋतभाषिन्.

Trump, *v. t.* क्लृप् c., सकूटं निर्मा 3 A; *See* **Fabricate.** -**Trumpery,** *a.* असार, कृत्रिम, कूट in comp. -*s.* असार-तुच्छ-द्रव्यं.

Trumpet, *s.* तूर्य, तूरी. 2 (Flower) पाटलाः, मोघा, काचस्थाली, फलेरुहा, कृष्णवृंता, कुबेराक्षी. -*v. t.* उद्-घुष् 10, प्रकाश् c., उच्चैः प्र-ख्या c. (ख्यापयति). -**er,** *s.* तूर्यवादकः. 2 उद्घोषकः.

Truncate, *v. t.* लू 9 U, अवच्छिद् 7 P.

Truncheon, *s.* यष्टि *f.*, दंडः, गदा.

Trundle, *See* **Roll.**

Trunk, *s.* (Of the body) कबंधः, अपमूर्धकलेवरं. 2 (Of trees) स्कंधः, प्र-कांडः-डं; 't. with the branches lopped off' स्थाणुः. 3 (Of elephants) शुंडः, शुंडा, -दंडः, हस्तः, करः. 4 भांडं. 5 अग्र-मुख्य-भागः.

Truss, *s.* पट्टः, बंधनं. 2 (तृण-) कूर्चः, भारः. -*v. t.* कील् 10, संबंध् 9 P, संसंज् c.

Trust, *v. t.* विश्वस् 2 P, प्रति-इ 2 P; *See* **Believe.** 2 निक्षिप् 6 P, सं-,अृ c. (अर्पयति), न्यस् 4 U; *See* **Entrust.** -*v. i.* Ex. by **Sure,** q. v.; 'learn to t. in God' ईश्वरासक्त-ईश्वराधीन-चित्तो भव, ईश्वरं शरणं प्रपद्यस्व; 't. to' आ-अव-लंब् 1 A, आश्रि 1 U. -*s.* विश्वासः, विश्रंभः, प्रत्ययः. 2 निक्षेपः, न्यासः. 3 कालिका, उद्धारः. -**ee,** *s.* निक्षेपधारिन् *m.* -**ing,** *a.* विश्वासिन्, विश्वस्त; 't. to the strength of his own arms' स्वभुजबलमवलंब्य. -**worthy,** -**y,** *a.* विश्वसनीय, विश्वास्य, विश्वासार्ह, विश्वासयोग्य, विश्रंभास्पदं-पात्रं-भूमिः, आप्त.

Try, *v. t.* परीक्ष् 1 A, अनु-भू 1 P; 'to t. their strength upon a traveller' पथिकमास्मच्छक्तिनिकषं कर्तुं. 2 (Cases) दृश् 1 P, वि-चार् c., अनुसं-धा 3 U, वि-विच् 3, 7 U; *See* **Judge;** 't. ing cases' व्यवहारदर्शनं; ददृशे संशयच्छेद्यान्व्यवहारान् (R. xvi. 39) 'tried contested cases'. -*v. i.* प्र-यत् 1 A, उद्यम् 1 A, व्यव-सो 4 P, प्रवृत् 1 A; *See* **Attempt;** oft. ex. by desid. forms. -**ing,** *a.* कष्ट-पीडाकर (री *f.*), (heat &c.). -**Trial,** *s* परीक्षा-क्षणं; 'to make a t. of' परीक्ष्; अनुभवः; 'under t.' अनुभूयमान. 2 व्यवहारदर्शनं, विचारः. 3 कृच्छ्रं, वि-आ-पद् *f.*

See **Calamity, Misfortune.** 4 प्र-,यत्नः, उद्यमः, उद्योगः.

Tryst, *s.* संकेतस्थानं. 2 समागमसंकेतः.

Tub, *s.* द्रोणि-णी *f.*

Tube, *s.* नालः-ली-लं, न(ना)लिका, नाडि-डी *f.*, सुषिरं, प्रणालः-ली. -**Tubular,** *a.* नालाकृति, नाडीरूप.

Tuber, *s.* कंदः-दं. -**ous,** *a.* ग्रंथिल, ग्रंथिमत्, कंदिन्.

Tubercle, *s.* सूक्ष्मव्रणः, ग्रंथिः.

Tuck, *See* **Fold.**

Tuesday, *s.* मंगलवासरः.

Tuft, *s.* चूडा, शिखा, शिखरः-रं, शेखरः; 'having a t.' शिखिन्. 2 पल्लवः; स्तबकः, गुच्छः अवतंसः. -**ed,** *a.* शिखिन्, शेखरित.

Tug, *v. t.* आ-कृष् 1 P, प्रयत्नेन कृष्; *See* **Pull.**

Tuition, *s.* शिक्षणं, अध्यापनं, उपदेशः.

Tumble, *v. i.* अवपत् 1 P, स्खल् 1 P. -*s.* अवपातः, स्खलनं.

Tumbler. *s.* काचपात्रं. 2 कत्थनः, कुशायणः.

Tumid, *a.* स्फीत, आध्मात.

Tumour, Tumefaction, *s* वि-,स्फोटः-टकः, शोफः, श्वयथुः, व्रणः-णं, मांसार्बुदं ग्रंथिः; 'fatty t.' मेदोर्बुदं.

Tumult, *s.* तुमुलं, संकुलं, अत्यंतमाकुलं; 't. in the army' विंजलः. 2 कोलाहलः, कलकलरवः. -**uous,** *a.* तुमुल, संकुल, क्षुब्ध, अव्यवस्थित.

Tune, *s.* रागः; तालः. 2 तालैक्यं, स्वरैक्यं; 'out of t.' विस्वर-*a.*; 'in t.' श्लिष्टस्वर, युक्तस्वर-*a.* -*v. t.* स्वरैक्यं कृ 8 U. -**ful,** *a.* सुस्वर, मधुर, संगतस्वर. *See* **Harmonious.**

Tunic, *s.* चोलः-ली, कूर्पासकः-कं.

Tunnel, *s.* कुल्या, सुरुं(रुं)गा, गूढ-भौम-मार्गः -*v. t.* उत्खन् 1 P, सुषिरीकृ 8 U.

Turban, *s.* उष्णीषः-षं, शिरोवेष्टनं.

Turbid, *a.* कलुष, आविल, पंकिल, सपंक, पंकदूषित, मलिन.

Turbulent, *a.* पीडाकर (री *f.*). दुर्दांत, कलह-तुमुल-कारिन्; अवज्ञकारिन्, अनवस्थित.

Turf, *s.* शाड्वलं, सतृणभूमि *f.*

Turgid, *s.* स्फीत, उच्छून.

Turmeric, *s.* हरिद्रा, कांचनी, पीता, निशा, वरवर्णिनी.

Turmoil, *s.* संक्षोभः, उपद्रवः, तुमुलं; 't. of war' संग्रामतुमुलं.

Turn, *v. i.* परि-,भ्रम् 1, 4 P, घूर्ण् 1 A, 6 P, व्या-परि-वृत् 1 A. 2 परिवृत्; oft. by भू 1 P, जन् 4 A. 3 अम्लीभू, अम्लतां यम् 1 P; 'food t. s into blood' अन्नं रुधिरभावेन परिणमति; *See* **Change;** 't. into white' श्वेतीभवति; 't. to nothing' निरर्थक-

त्यर्थ-*a*. भू. 4 भू with संमुख-अभिमुख-(खी *f*.) in comp. or with gen.; 't. ing to the hero' नायकाभिमुखी भूत्वा. -*v. t.* परि-,भ्रम् c., (*fig*. also), घूर्ण् c.; परि-वि-अपा-वृत् c. 2 परिवृत् c., आ-,वेल् c., (आवलितवदनं राजकमासीत् Ka. 10); परिवृत्तार्धमुखी (V. 1) 'with her face half-t.-ed'. **3** विपर्यस् c. 4 साचीकृ 8 U; *See* **Bend**. **5** अन्वीकृ; 't. to account; *See* under **Account**; 't. to use' उपयुज् 10; 't. into ashes' भस्मसात्-भस्मी-कृ or भू; 't. the back' पृष्ठं दृश् c., पराङ्मुखीभू 't. s a single fault to two' एकापराधं द्विगुणीकरोति. **-about,** वि-परि-वृत्; परिक्रम् 1 U, 4 P. **-against,** प्रतीपयति (D.); (*v. i.*) प्रतिकूलीभू, प्रत्यर्थिन्-*a*. भू, विरुद्ध-*a*. भू. **-away,** अपनी 1 P, दूरीकृ; अपास्, निःसृ c., निराकृ; *See* **Dismiss, Discharge**. **2** (aside) नि-व्यावृत् c., सं-हृ 1 P; साचीकृ, तिर्यग्-वल्; (अभिमुखे मयि संहृतमीक्षितं S. 2); 'shall t. away his mind (in another direction)' अन्यतः एनं क्षिपामि-संचारयामि; (*v.i.*) व्यावृत् 1 A, (व्यावर्तमाना ह्रिया), पराङ्मुखी विमुखी-भू; मुखं परिवृत्. **-back,** परि-परा-वृत्; (*v. t.*) परि-परा-वृत् c. **-into,** कृ, (तपोवनमुपवनं कृतं S. 2). **2** परिणम् c. with भावेन; आखुं बिडालभावेन पर्यणमयत् 't.-ed the rat into a cat'; *See* **Change. off,** दूरीकृ, निवृत् c., अपास् &c.; (*v. i.*) अपसृ 1 P, निर्गम् 1 P. **-out,** (*v. t.*) निःसृ c., निष्कस् c., बहिष्कृ; *See* **Discharge**; (*v. i.*) संपत् 1 P; *See* **Happen**. **2** जन् 4 A, भू 1 P; 't. ed out pale' विवर्णीभूतः, सहसा विवर्णभावं प्रपेदे; 'the words of the great never t. out untrue' न हीश्वरव्याहृतयः कदाचित्पुष्णंति लोके विपरीतमर्थं (K. III. 63). **-over,** उत्क्षिप् 6 P. **2** परिवृत् c.,चल् c.;'t. ing over the pages' पृष्ठानि चालयित्वा-समालोक्य. **-round,** परि-परा वृत्. **-to,** दृश् 1 P, ईक्ष् 1 A; by प्रति with acc. **-towards,** अभिमुखी-संमुखी-भू (with gen.). **-up,** सहसा आविर्भू or प्रादुर्भू. **2** **Happen,** q. v. -*s*. आवर्तः-र्तनं, आवृत्ति *f*. **2** परिवृत्तिः, परिवर्तः, विकारः. **3** पर्यायः, परिवृत्तिः; 'by t. s' पर्यायेण, पर्याय in comp.; 'service by t. s' पर्यायसेवा. **4** वारः, (शशकस्य वारः समायातः P. I. 8). **5** प्र-,वृत्तिः, भावः, दशा; 't. of mind' चित्तवृत्तिः, मनःस्वभावः **6** आकारः, स्वरूपं; 'matters took a different t.' वस्तुस्थितेरवस्थांतरं अदृश्यत,सकलोऽर्थः परिवृत्तः. **7** गति *f*., क्रमः; 'mysterious is the t. of fate' कर्मणो गहना गतिः; 't. of fortune' दैवगतिः. **8** परिक्रमः; (walk) ईषद्विहारः. **9** अवसरः, समयः, कालः. **10** वंकः (of rivers); 'a good t.' उपकारः; 'ill t.' अपकारः; 'one good t. deserves another' उपकारः प्रत्युपकारेण निर्यातयितव्यः. **-er,** *s*. चक्रिन् *m*., कुंदिन् *m*. **-Turncoat.** *s*. स्वपक्षत्यागिन् *m*., समयानुरोधिन्.

Turnip, *s*. शिखामूलं.

Turpentine, *s*. देवदारुतैलं, सरलद्रवः.

Turpitude. *s*. दुष्टता, दोषः.

Turquoise, *s*. वैदूर्यं, हरिताश्मन् *m*.

Turret, *s*. शिरोगृहं; प्रासादशृंगं-शिखरं.

Turtle, *s*. कूर्मः; *See* **Tortoise**.

Tusk, *s*. दंतः, दंष्ट्रा, रदः, रदनः.

Tussel, *s*. बाहुयुद्धं. -*v. i*. प्रति-आ-युध् 4 A.

Tutelage, *s*. बालावस्था, बाल्यं.

Tutelary, *a*. रक्षक, रक्षा in comp.; 't. deity' इष्ट-कुल-देवता.

Tutenag, *s*. तुत्थं, तुत्थांजनं.

Tutor, *s*. गुरुः. अध्यापकः, आचार्यः, शिक्षकः **-ship,** *s*. आचार्यत्वं.

Twaddle; *See* **Prate**.

Twain, *s*. (In t.) द्विधा, द्वेधा.

Twang, *v. t*. (A bow) आ-स्फल् c., टंक् 8 U, ज्यां घुष् 10; (a lute) क्वण् c., नद् c. -*v. i*. क्वण् 1 P, टंकारं कृ 8 U -*s*. टंकारः, ज्या-शब्दः-घोषः, धनुरास्फालनं. **2** क्वणितं, झणत्कारः.

Tweak, *See* **Pinch**.

Tweezer, *s*. संदंशः, कंकमुखं.

Twelve, *a*. द्वादशन्. **-Twelfth,** *a*. द्वादश (शी *f*.). -*s*. द्वादशांशः.

Twenty, *a*. विंशति *f*. **-Twentieth,** *a*. विंश (शी *f*.), विंशतितम (मी *f*.).

Twig, *s*. विटपः, शाखा, प्रशाखा.

Twilight, *s*. संध्या, संधिप्रकाशः,संध्याकालः-समयः, निशादिः.

Twin, *a. s*. यम, यमज, यमल; 'we are t. brothers' भ्रातरावावां यमजौ (U. 6); oft. by यमलं, युगं, द्वंद्वं, मिथुनं, युगलं; 't. stars' मिथुनं; 'one of t.' यमः, यमलः.

Twine, *s*. सूत्रं, तंतुः. -*v. t*. उद्-ग्रंथ् 9 P, उत्खच् 10, (कुसुमोत्खचितान्वलीभृतश्चलयन् अलकान्. R. VIII. 53). **2** (Itself) आ-परि-वेष्ट् c., आ-परि-वृत् c.

Twinge, *s*. व्यथा, पीडा, वेदना, शलःलं, तीव्रवेदना. -*v. t*. Ex. by कृ with (*s*.).

Twinkle, *v. t*. (Of the eye) नि-,मिष् 6 P, उन्मिष्, निमील् 1 P. उन्मील्, निमेषोन्मेषं कृ. **2** स्फुर् 6 P, तरलं-सकंपं-प्रभा 2 P or प्रकाश् 1 A or द्युत् 1 A. -*s*.,**-ing,** *s*. निमि(मे)षः, निमेषोन्मेषौ; 'within the t. of the eye' निमेषमात्रात्, निमेषेण. **2** स्फुरणं, स्फुरितं, तरलज्योति *n*., प्रभा; 'the

eyes knowing no t.' (पक्ष्मनिमेषाल- सपक्ष्मपंक्तिः (R. II. 19), अनिमेषलोचनो दृष्टः (Ka. 11).

Twirl, *v. t.* त्वरितं भ्रम् c. or परि-वृत् c. —*v. i.* परि-वृत् 1 A, भ्रम् 1,4 P. —*s.* त्वरित-परिवृत्ति *f.*

Twist, *v. t.* नि-व्या-वृत् c., आकुंच् c., मुड्-ब्रू 10. —*v. i.* व्यावृत् 1 A, आकुंच् pass. —*s.* व्यावर्तनं, आ-,कुंचनं, मोटनं.

Twit, *v. t.* *See* **Censure, Taunt.**

Twitch, *v. t* (सहसा) आकृष् 1 P, आ-क्षिप् 6 P. —*v. i.* स्फुर् 6 P, स्पंद् 1 A, प्र-,कंप् 1 A. —*s.* सहसाकर्षः-आक्षेपः, स्फुरणं, स्पंदनं

Twitter, *v. i.* प्र-जल्प् 1 P, प्र-लप् 1 P. —*s.* प्रलापः, प्रजल्पः; *See* **Chatter.**

Two, *a.* द्वि (द्वौ, द्वे *f.* *n.*), द्वि pr.; द्वयं affixed; 't. years' द्विवर्षं, वर्षद्वयं; 't. or three' द्वित्राः; 't.-fold' द्विगुण; 't.-handed' द्विहस्त; द्विजिह्व &c.; 'in t. ways' द्विधा. —**Twice,** *adv.* द्विः, द्विवारं; 't. married' पुनर्भू, पुनर्भूः (widow remarried); '20 is t. 10' द्विरावृत्ता दश विंशतिः संपद्यते.

Tympanum, *s.* कर्णोदरं, कर्णदुंदुभिः.

Type, *s.* आदर्शः; प्रतिरूपं; *See* **Model** 2 रचिह्न, लक्षणं, व्यंजनं. 3 मुद्राक्षरं. 4 प्रकारः, रीति *f.* —**ical,** *a.* Ex. by (*s.*) in comp.: आदर्शभूत, प्रतिरूपक. —**Typefy,** *v. t.* आदर्शीकृ 8 U, प्रतिरूपेण दृश् c. —**Typography,** *s.* मुद्राकर्म.

Tyranny, *s.* प्रजापीडनं, लोकोपद्रवः, जनमर्दनं, निष्ठुरशासनं. —**ic,-ical,** *a.* प्रजोपद्रविन्, प्रजोपद्रविन्. —**ize,** *v. t.* (भृशं) पीड् 10, उप-द्रु 1 A, विप्र-कृ 8 U, उपद्रु 1 P. —**Tyrant,** *s.* प्रजापीडकः, लोकोपद्रावकः, उपद्राविन् *m.*, निष्ठुरशासनः.

Tyre, *s.* नेमि *f.*

Tyro, *s.* नवच्छात्रः-शिष्यः, अनभ्यस्तः.

U.

Ubiquitous, *a.* सर्वगत, सर्वव्यापिन्.

Udder, *s.* ऊधस् *n.*, आपीनं, स्तनं (mostly human); 'having pot-like u. s' घटोध्नी; 'having large u. s' पीनोध्नी.

Ugly, *a.* कु-वि-अप-रूप, विकृत, कदाकार; दुर्दर्शन, विकृताकार. 2 कुत्सित, निंद्य. —**iness,** *s.* वैरूप्यं, अपरूपता, कदाकारः.

Ulcer, *s.* पूयव्रणः-णं, रविव्रधिः, नाडीव्रणः-णं, पूयवर्त. —**ate,** *v. t.* व्रणं उत्पद् c. —*v. i.* सव्रणीभू 1 P, व्रणं बंध् 9 P. —**ated,-ous,** *a.* पूयवाहिन्, सव्रण, सक्षत, उपहत in comp. with (*s.*).

Ulterior, *a.* उत्तर, अपर; *See* **Distant.**

Ultimate, *a.* चरम, अंतिम; *See* **Last.** —**ly,** *adv.* अंते, शेषे, अंततः. —**Ultimatum,** *s.* चरमाभिसंधिः, अंत्यप्रतिज्ञा.

Ultra, *a.* ex. by अति in comp.

Ultra-marine, *a.* द्वीपांतरभव.

Umbilical, *a.* नाभ्य, नाभि in comp.; 'u. cord' नाभि *f.*,-नालः.

Umbra, *s.* पूर्णच्छाया.

Umbrage, *s.* छाया. 2 अप्रीति *f.*, कोपः, असंतोषः, अपराधः; 'take u.' प्र-,कुप् 4 P, **Angry,** q. v.; 'give u.' विरागं नी 1 P; *See* **Insult.**

Umbrella, *s.* छत्रं, आतपत्रं, घर्मवारणं, अलक्तं.

Umpire, *s.* मध्यस्थः, निर्णेतृ *m.*

Un, A prefix, ex. by अ (अन् before vowels), sometimes by निर्, वि, दुस् pr., हीन, रहित in comp.; 'unaided' असहाय, साहाय्यहीन; 'undaunted' निर्भीक, अभय; 'unmixed' अ-मिश्र; 'unwelcome' अप्रिय, अनभिमत &c.; 'unattainable' दुष्प्राप. (In cases where the word formed with 'un' is not given, the student should take the simple word or form it, and use the above prefixes. With nouns the sense of 'un' may be expressed by अप-नी 1 P, or हृ 1 P; *e. g.* 'unbar' अर्गलं अपनी, निरर्गलीकृ &c.).

Unaccustomed, *a.* अपरिचित, अनभ्यस्त, अननुभूत.

Unaffected, *a.* अकृत्रिम, सहज, अव्याज; *See* **Artless.**

Unanimous, *a.* एकमत-चित्त. —**ly,** *adv.* एकचित्तीभूय, ऐकमत्येन. —**Unanimity,** *s.* ऐकमत्यं, चित्त-मत-ऐक्यं, एकचित्तता; अस्मिन् विषये सर्वेषामैकमत्यं 'there is a u. on this point.'

Unarmed, *a.* निःशस्त्र, निरायुध, असज्ज.

Unassailable, *a.* दुष्प्रधर्ष, अधृष्य, दुरासद.

Unassuming, *a.* अविकत्थन, अदृप्त, विनीत *See* **Humble.**

Unavailing, *a.* निरर्थक, निर्गुण, निष्फल.

Unawares, *adv.* अतर्कितं, अलक्षितं, निभृतं, अकस्मात्; *See* **Suddenly** also.

Unbar, Unbolt, *v. t.* निरर्गलयति (D.).

Unbeliever, *s.* नास्तिकः,-बुद्धिः, पाखंडः मिथ्यादृष्टिः.

Unbend, *v. t.* शिथिलीकृ 8 U; *See* **Relax.** —**ing,** *a.* **Cruel,** q. v.

Unbind, *v. t.* उद्-ग्रंथ् 9 P, शिथिलीकृ 8 U.

Unblemished, *a.* निष्कलंक, निरवद्य, अक्षत.

Unbosom, *v. t* विवृ 5 U; *See* **Disclose;** 'u. oneself' हृदयं-मनोगतं-विवृ.

Unbounded, *a.* अनंत, अमित.

Unbridled, *a.* उच्छृंखल, उद्दाम, निर्मर्याद, अनर्गल.

Unburden, *v. t.* भारमपनी 1 P; *See* **Alleviate** also.

Unceremonious, *a.* अनादर, मंदादर. **-ly,** *adv.* मंदादरेण.

Uncertain, *a.* संदिग्ध, संशयग्रस्त; *See* **Doubtful. -ty,** अनिश्चयः, अनिर्णयः.

Unchain, *v. t.* निगडान् अपनी 1 P, मुच् c.; *See* **Free, Liberate.**

Uncharitable, *a.* दोषदृष्टि, असूयक, छिद्रान्वेषिन्.

Unchaste, *a.* अविनीत, पांसुल, &c.; *See* **Prostitute.**

Unclaimed, *a.* अस्वामिक, अनधिकृत.

Uncle, *s.* पितृव्यः. **2** मातुलः (maternal u.)

Unclose, *v. t.* **Open,** q. v.

Unclothe, *v. t.* **Strip,** q. v. **-ed,** *a.* विवस्त्र, नग्न; *See* **Naked.**

Uncloven, *a.* अविदीर्ण, अस्फुटित. 'u. hoofed,' एकशफ, एकखुर.

Uncommon, *a.* असामान्य, अपूर्व, अलौकिक (की *f.*). **-ly,** *adv.* अपूर्वं; *See* **Exceedingly.**

Uncompromising, *a.* प्रतिनिविष्ट, स्थिर, निश्चल; आग्रहिन्.

Unconcern,-ed, *a.* **Indifferent,** &c. q. v.

Unconscionable, *a.* विवेकशून्य.

Unconscious, *a.* निःसंज्ञ, अपगतचेतन, मूर्छित. **2** अनभिज्ञ.

Uncontrolled, *a.* अप्रतिबंध, निरर्गल, निर्यंत्रण.

Uncouple, *v. t.* **Separate,** q. v.

Uncouth, *a.* **ugly, Strange,** q. v.

Uncover, *v. t.* उच्छद् 10, अपा-वि-वृ 5 U; *See* **Strip;** 'they u. ed their heads' शिरोवेष्टनमपनिन्युः.

Unction, *s.* अभि-,अंजनं, आ-वि-लेपः-पनं. **-Unctuous,** *a.* स्निग्ध, मसृण, चिक्कण, सांद्र.

Undeceive, *v. t.* भ्रमं निरस् 4 U or अपाकृ 8 U or छिद् 7 P.

Undecided, *a.* अनिश्चित; (of persons) **irresolute,** q. v.

Undeniable, *a.* निर्विवाद, निःसंदेह.

Under, Underneath, *prep.* अधः, अधस्तात् (with gen.); *See* **Below;** तले in comp. or with gen. **2** अधीन, आयत्त, वशग; *See* **Subject. 3** (**Age** &c. ऊन in comp.; 'u 16,' ऊनषोडशवर्ष; 'u. age' अप्राप्तवयस्क, अप्राप्तव्यवहार 'should bury one who is u. two years' ऊनद्विवर्षं निखनेत् (Y. III 1.). **4** काले, समये or ex. by 'Reign', q. v. 'u. the Moghuls' मोंगलेषु महीं शासत्सु; gen. ex. by loc. or instr.; 'u. this condition' अनेन समयेन; 'u. misfortunes' आपदि, आपत्काले; 'u. your favour.' भवतोऽनुग्रहेण, **-a.** अधर, अधः in comp.; **Under-current,** *s.* अधः or अंतःप्रवाहः. 'u.-garment' अधोंशुकं, अधोवासस् *n.*; *See* **Garment;** oft. by उप pr.

Undergo, *v. t.* अनुभू 1 P, सह् 1 A, उपगम् 1 P; *See* **Suffer;** 'u. examination' परीक्ष् pass.; 'u. change' परिवृत् 1 A. विकृ pass.

Underground, *a.* आंतर्भौम, भूम्यधस्तात्.

Underhand, *a.* गूढ, प्रच्छन्न, परोक्षकृत, छलेन कृत; निंद्य, गर्हणीय.

Underlay, *v. t.* अधः नि-धा 3 U or स्था c.

Underlie, *v. t.* शी 4 A, निगुह् pass. (with loc.).

Underline, *v. t.* अधोरेखया अंक् 10.

Underling, *s.* अनुजीविन् *m.*

Undermine, *v. t.* सुरंगां कृ 8 U, उत्खन् 1 P, अधस्तात् विनश् c. **2** विनश् c., अवसद् c., उच्छिद् 7 P, कष् 1 P; 'a river u.-ing its banks' कूलंकषा सिंधुः.

Underrate, Undervalue, *v. t.* न्यूनमूल्यं क्लृप् c., अर्घतः पत् c. **2** लघु मन् 4 A, अवमन्, लघूकृ, अपकृष् 1 P.

Understand, *v. t.* बुध् 1 P, ज्ञा 9 U, अवगम् 1 P, ग्रह् 9 U, उपलभ् 1 A, वि-बुध् c., अव-इ 2 P, अवधृ 10; *See* **Know. 2** (Words &c.) अध्याहृ 1 P, ऊह् 1 A, (इदं पदमध्याहर्तव्यं). **-ing,** *s.* मतिः, बुद्धिः, धीः, मेधा, ग्रहण-ज्ञान-शक्तिः, प्रज्ञा; *See* **Intellect. 2** भावः, वृत्ति *f.*; 'good u.' सद्भावः, मित्रभावः; 'come to an u.' *See* **Settle.**

Undertake, *v. t.* आरभ् 1 A, उपक्रम् 1 A; *See* **Begin. 2** व्यवसो 4 P, ईह् 1 A; *See* **Attempt, Intend.** 3 स्वी-अंगी-कृ 8 U, उ (ऊ) रीकृ, अभ्युपगम् 1 P, अभ्युप-इ 2 P, प्रति-पद् 4 A. **-er,** *s.* आरंभकः, अनुष्ठातृ *m.* **2** प्रेतकर्मनिर्हारकः. **-ing,** *s.* कार्यं, व्यवसायः, कर्मन् *n.*, आरंभः, व्यापारः, प्रवृत्ति *f.*

Underwood, *s.* गुल्मः-ल्मं; स्तंबः.

Underworld, *s.* अधो-भुवनं-लोकः.

Undeserving, *a.* अनर्ह, अगुणवत्, अपात्र, निर्गुण.

Undesigned, *a.* अनभिप्रेत, अबुद्धिपूर्व. **-ly,** *adv.* अज्ञानतः, अबोधपूर्वं, अकामतः.

Undesigning, *a.* **sincere,** q. v.

Undiminished, *a.* अक्षत, अन्यून, अनपाय, अलुप्त, अक्षीण.

Undisguised, *a.* **Frank,** q. v.

Undivided, *a.* अभिन्न; (attention) एकाग्र, अनन्य, अनन्यासक्त, सुसमाहित; *See* Fixed.

Undo, *v. t.* उन्मुच् 6 P, उद्-ग्रथ् c., श्रथ्-श्रन्थ् 9 P. 2 व्या-परा-वृत् c.; 'able to do, not to do, or u. things' कर्तुमकर्तुमन्यथा कर्तुं क्षमः. 3 हन् 2 P, नश् c.; 'Oh! I am undone हा हतोस्मि (मंदभाग्यः), दैवेन मुषितोस्मि.

Undress, *v. t.* वासः-वस्त्रं-अपनी 1 P or अपवृ c. or उन्मुच् 6 P or अपनुद् 4 P. –*s.* लघुवासस् *n.* –**ed.** *a* (food) असंस्कृत, अपक्व, आम.: 2 विवस्त्र, विवसन, उन्मुक्तवसन.

Undulate, *v. i.* तरंगायते (D.), उत्प्लु 1 P; better by 'u. -ing.' –**ing,-ory**, *a.* ऊर्मिमत्, तरंगित, उन्नतानत, भंगुर, उत्तरंगिन्. –**ion**, *s.* भंगुरता, ऊर्मिमत्ता, &c.

Unearth, *v. t.* उत्खन् 1 P.

Uneasy, *a.* आतुर, चिंताकुल.

Unequalled, *a.* *Matchless*, q. v.

Unerring, *a.* अमोघ, अभ्रांत, अवंध्यपात; 'took an u. aim on his bow' धनुषि अमोघं समधत्त बाणं; *See* Fix.

Uneven, *a.* विषम, उन्नतानत.

Unexpected, *a.* असम्भावित, अतर्कित, आकस्मिक (की *f.*), अकांड, अनपेक्षित, अचिंतितपूर्व. –**ly**, *adv.* अकस्मात्, अकांडे, अतर्कितं.

Unfaithful, *a.* Faithless, q. v.

Unfasten, *v. t.* Loose, q. v.

Unfathomable, *a.* अगाध, अतलस्पर्श.

Unfavourable, *a.* प्रतिकूल, वि-पराङ्-मुख (खी *f.*), विरक्त, अननुकूल; विषम, अप्रिय, अप्रसन्न.

Unfeeling, *a.* निर्दय, क्रूर, *See* Cruel.

Unfeigned, *a.* अकृत्रिम, निर्व्याज.

Unfit, *a.* अयोग्य, अक्षम, &c. –*v. t.* Disable, q. v.

Unfold, *v. t.* विस्तृ-स्तृ c. 2 विवृ 5 U; *See* Disclose.

Unforeseen, *a.* Unexpected, q. v.

Unfortunate, *a.* अभाग्य, दुर्दैव, मंद-हत-भाग्य, दैवोपहत, आपद्ग्रस्त. 2 अमंगल, अभद्र, अशुभ. –**ly**, *adv.* मंदभाग्यतया, दुर्दैवात्.

Unfounded, *a.* अमूलक, निर्मूल, मिथ्या in comp.

Unfruitful *a.* Fruitless, q. v.

Unfurl, *See* Unfold.

Ungainly, *a.* Clumsy, q. v.

Ungodly, *a*, पाप, धर्मभ्रष्ट.

Ungovernable, *a.* अवश्य, अविधेय, अनिवार्य, दुर्निवार, दुर्निग्रह, उद्दाम, निरंकुश, उच्छृंखल.

Ungrateful,-ness *See* Ingrate &c.

Unguent, *s.* अभ्यंजनं, अनु-वि-लेपः-पनं, प्रसाधनं-अंगरागः.

Unhappy, *a.* अभव्य, मंदभाग्य, दुःखार्त, अनिर्वृत; *See* Miserable.

Unharmed, *a.* अक्षत, निर्विघ्न.

Unharness, *v. t.* मुच् c.

Unhealthy, *a.* अस्वस्थ, रोगावह.

Unhinge, *v. t.* विपर्यस्तीकृ 8 U, अव्यवस्थीकृ.

Unhurt, *See* Unharmed.

Unicorn, *s.* एकशृंगः.

Uniform, *a.* सवर्ण, एक-समान-विध, एक-समान-रूप, एकप्रकार, एकाकार; सम, समान, अविशेष. –*s.* निर्दिष्टवेषः वेषः. –**ity**, *s.* सारूप्यं, ऐकविध्यं, साम्यं, एकरूपता. –**ly**, *adv.* नित्यं, अजस्रं, अविरतं, एकरूपेण, सततं.

Unimpeachable, *a.* निर्दोष.

Unimpeded, **Uninterrupted**, *a.* निर्विघ्न, निरंतर, अनंतराय, अविच्छिन्न, अविरत.

Unique, *a.* अपूर्व, अद्वितीय, अप्रतिम.

Unison, *s.* एकतानः, स्वरैक्यं.

Unit, *s.* एकः, एकांकः. –**Unity**, *s.* एकत्वं, अद्वैतं; 'doctrine of u.' अद्वैतवादः, अभेदः. 2 ऐक्यं, एकचित्तता. –**Unitarian**, *s.* अद्वैतवादिन् *m.*

Unite, *v. t.* युज् 7 U, 10, सं-समा-°, संघट् c., संहन् 2 P, समानी 1 P, सं-धा c., सं-युज् 7 P, 2 A, सं-धा 3 U; 'seems u. -ed' भवति कृतसंधानमिव (S. 1). –*v. i.* घट् 1 A, (तदेव तत्समयमां घटनाय योग्यं V. 2), सं-युज् pass; एकत्र भू, सं-,मिल् 6 P; *See* Assemble. –**ed**, *a.* संहत; मिलित्वा; संयुक्त. –**edly**, *adv.* संभूय, मिलित्वा, एकीभूय, संहत्य. –**Union**, *s.* संघः, संगमः, समागमः, संहति *f.*, संहति *f.*, समवायः, सं-,योगः, संधिः; 'u. is strength' समवायो हि दुर्जयः; (*cf.* बहूनामप्यसाराणां संहतिः कार्यसाधिका 'weak faggots make a strong bundle').

Universe, *s.* विश्वं, सर्वं जगत्, त्रिभुवनं; *See* World. –**al**, *a.* विश्व, सार्वलौकिक-सार्वत्रिक-(की *f.*); सर्वगत, सर्व; 'u. spirit विश्वात्मा, जगदात्मा, ब्रह्म. –**ality**, *s.* सर्वगतत्वं, अभिव्यापित्वं. –**ally**, *adv.* सर्वतः, सर्वत्र, विश्वतः, विश्वक्. [मंडलं.

University, *s.* विद्यालय-मंडलं-सभा, शास्त्र-

Univocal, *a.* एकार्थ, ऐकवाचिक (की *f.*).

Unkempt, *a.* अप्रसाधित.

Unkind, *a.* अस्निग्ध, निर्मम, निर्दय. क्रूर. –**ness**, *s.* निर्दयता, &c. 2 अपकारः, अहितं

Unlace, *v. t.* *See* Free.

Unlawful *a.* Illegal, q. v.

Unlearn, *v. t.* स्मृतेः भ्रंश् 4 U, वि-स्मृ 1 P. –**ed**, *a.* अज्ञान, अकृतविद्य.

Unless, *conj.* न-नो-चेत्, यदि न.

Unlicensed, *a.* निरंकुश, निर्गल.

Unload, *v. t.* भारं अप-नी 1 P or अप-वह् c. or अवतॄ c.; *See* Disburden.

Unlock, *v. t.* उद्-घट् c., उन्मुद्रयति (D.).
Unloose, *See* **Loose,-en.**
Unman, *v. t.* पौरुषं भञ्ज् c. or हृ 1 P. **-ly,** *a.* क्लीब, पौरुषहीन, पुरुषानर्ह.
Unmask, *v. t.* छद्मवेषं अपहृ 1 P, (fig.) निजरूपं प्रकटीकृ 8 U; 'he was u. ed' तस्य वास्तविकं स्वरूपमाविष्कृतं.
Unmeaning, *a.* अनर्थक, असंगत, अपार्थ.
Unmoor, *v. t.* उन्मुच् 6 P or c.
Unmoved, *a.* स्थिर, अविचलित, निर्विकार.
Unnatural, *a.* निसर्ग or सृष्टिक्रम-विरुद्ध or बाह्य.
Unnecessary, *a.* निष्प्रयोजन, वृथा in comp.
Unnerve, *v. t.* **Enfeeble,** q. v.
Unpack, *v.t.* उद्-घट् c., कोशात् निष्कृष् 1 P.
Unparalleled, *a.* निरुपम, अतुल.
Unprecedented, *a.* अपूर्व.
Unpretending, *a.* विनयशील.
Unprincipled, दुर्वृत्त, विचारहीन, सदसद्विवेकहीन.
Unravel, *v. t.* उद्-ग्रंथ् 9 P, व्याकृ 1 U, व्या-ख्या 2 P.
Unreal, *a.* असार, मायात्मक, अतथ्य.
Unrelenting, *a.* *See* **Cruel.**
Unremitting, *a.* दृढ, अशिथिल.
Unreserved, *a.* अशेष, निःशेष, सं-,पूर्ण.
Unrest, *s.* चिंता, वैक्लव्यं, क्षोभः, अनिर्वृतिः *f.*
Unrestrained, *a.* निरवग्रह, उच्छृंखल, उद्दाम, निर्यंत्रण, अनर्गल, निरंकुश.
Unrivalled, *a.* अप्रतिम, अद्वितीय, अतुल, अप्रतिरूप; अनुपम.
Unroll, *v. t.* *See* **Open.**
Unruly. *a.* **Ungovernable,** q. v.
Unsaddle, *v. t.* पर्याणं अपनी 1 P.
Unscrupulous, *a.* निःशंक, शंकाहीन.
Unseal, *v. t.* मुद्रां अपनी 1 P, उद्-घट् c., उन्मुद्रयति (D.).
Unsettle, *v. t.* आकुलीकृ 8 U, क्षुभ् c., आकुलयति (D.); *See* **Agitate. -ed,** *a.* अस्थिर, आकुल, क्षुब्ध.
Unshackle, *v. t.* *See* **Free.**
Unsheathe, *v. t.* कोशात् उद्-हृ 1 P or निष्कृष् 1 P. **-ed,** *a.* विकोश, उल्लसित.
Unsightly, *a.* अप्रिय-विरूप-दर्शन, कुरूप; *See* **Ugly.**
Unsophisticated, *a.* निर्व्याज, निर्व्यलीक, सरल, ऋजु.
Unsound, *a.* असार, अयुक्तिसिद्ध.
Unspeakable, *a.* अवर्णनीय. **2** अवाच्य.
Unspotted, *a.* निष्कलंक, विमल.
Unstable, *a.* अस्थिर, चंचल.
Unsteady, *a.* *See* **Fickle.**
Unstring, *v. t.* (A bow) ज्यां अपनी 1 P or शिथिलयति (D.); 'a bow unstrung' शिथिलज्याबंधं धनुः (S. 2).

Unsuitable, *a.* अन्-उपपन्न-उचित.
Unswerving, *a.* स्थिर, दृढ, अचल.
Untenable, *a.* अरक्षणीय, अप्रतिपादनीय.
Untie, *v. t.* उद्-मुच् c., मोक्ष् 10, उद्-ग्रंथ् 9 P, शिथिलयति (D.).
Until, *prep.* *See* **Till.**
Untimely. *a.* अकाल in comp.; oft. अप pr.
Unto, *prep.* *See* **To.**
Untoward, *a.* प्रतिकूल, प्रतीप, अभद्र, वाम.
Untwist, Untwine, Unveil Unwrap, *See* *v. t.* **Open.**
Unusual, *a.* अपूर्व, असामान्य, अलौकिक (की *f.*).
Unvarnished, *a.* यथार्थ, यथातथ, अनलंकृत.
Unwholesome, *a.* अपथ्य, अहितावह.
Unwieldy, *a.* स्थूल, अतिमहत्, अनुत्थानयोग्य.
Unwittingly, *adv.* अज्ञात्वा, अज्ञानात्.
Unworthy, *a.* अनर्ह, अयोग्य, निर्गुण; oft. by अ; 'u. object' अपात्रं, अकार्यं, &c.
Unyoke, *v. t.* मुच् c., मोक्ष् 10. **2** वियुज् 10.
Up, *prep., adv.* उत् prefixed; ऊर्ध्वं, उपरि, उच्चैः; 'up to' *See* **Till;** आप्रदानात् 'up to being given away' आफलोदयकर्मणां &c.; 'be up and doing' कार्योद्यतो भव; 'ups and downs' पातोत्पाताः; *See* **Down. -per,** *a.* उपरितन (नी *f.*), उपरिस्थ, ऊर्ध्व, उत्तर; 'to get the u. hand' अभि-भू 1 P, अतिरिच् pass; *See* **Excel.**
Upbraid, *v. t.* निर्भर्त्स् 10 A; *See* **Reproach.**
Uphold, *v. t.* समर्थ् 10, दृढयति (D.), उत्तंभ् 9 P, सं-धृ 10, आ-अव-लंब् 1 A; *See* **Support.**
Upholsterer, *s.* गृहोपस्करविक्रयिन् *m.*
Upkeep, *s.* रक्षा, रक्षणं.
Upland, *s.* उपरिभूमि *f.*, अधित्यका.
Uplift, *v. t.* उद्यम् 1 A, उत्था c., (उत्थापयति), उच्छ्रि 1 U; *See* **Raise.**
Upon, *prep.* *See* **On.**
Upraise, *See* **Uplift.**
Upright, *a.* उन्नत, उच्छ्रित, दंडवत् *ind.*, ऋजु. **2** सरल, सत्यात्मन्, ऋजु; *See* **Honest. -ly,** *adv.* दंडवत्; ऋजु, सारल्येन.
Uproar, *s.* कोलाहलः, कलकलः, तुमुलं.
Uproot, *v. t.* उन्मूल् 10, मूलात् छिद् 7 P, उत्पट् 10, उद्धृ 1 P; *See* **Eradicate.**
Upset, *v. t.* परिवृत् c., पर्यस् 4 U. **-s.** पर्यासः, परिवर्तनं; *See* **Overturn.**
Upshot, *s.* परिणामः, पर्यवसानं.
Upside, *s.* अधरांशः; 'u.-down' अधरोत्तर *a.*, अधोमुख *a.*, 'turn u.-down' अधोमुखीकृ.

Upstart, *s.* नवोद्भवः, नवोत्थानः, नवर्द्धिः, आगंतुकः.

Upward, Upwards, *adv.* ऊर्ध्वं, उपरि. 2 अधिक in comp.; अधिकत्रिंशा नराः 'u. of 30'; पर, परः in comp. (परःसहस्राः शरदः U. 1).

Urban, *a.* पौर (री *f.*). नागरिक (की *f.*). 2 सुजन, सुशील, दक्षिण. **-ity,** *s.* दाक्षिण्यं, नागरिकवृत्ति *f.*, सौजन्यं.

Urchin, *s.* (दुष्ट-) बटुः, माणवकः.

Urethra, *s.* मूत्रमार्गः-द्वारं.

Urge, *v. t.* प्रोत्सह् c., प्रचुद् 10, उत्तिज् c., प्रणुद् 6 P or c., प्रवृत् c.; *See* **Prompt.** 2 निर्बंधेन प्रच्छ् 6 P, अनुनिर्बंध् 9 P; *See* **Importune.** **-ency,** *s.* गौरवं, गुरुता, भारः. 2 निर्बंधः, आग्रहः. **-ent,** *a.* गुरु, आवश्यक (की *f.*), अपरिहार्य, अविलंब्य. **-ently,** *adv.* निर्बंधेन. 2 आशु, अपरिहार्यतया.

Urine, *s.* मूत्रं, प्रस्रावः, मेहः. **-v. i.** मूत्र् 10. **-al,** *s.* मूत्रपात्रं-भाजनं. **-ary,** *s.* मूत्रस्थानं. **-a.** मूत्र in comp.

Urn, *s.* (जल-) कुंभः, कलशः-सः, भाजनं.

Ursa-major, *s.* सप्तर्षयः.

Usage, *s.* प्रयोगः. 2 व्यवहारः, आचारः, आचरणं, वृत्ति *f.*; 'conventional u.' रूढि *f.*

Use, *v. t.* प्र-उप-युज् 7 A, 10, व्यव-हृ c., व्याहृ c., उप-,युज् 7 U, सेव् 1 A; धृ 10 (clothes &c.). 2 प्र-युज्; 'is used in the sense of *Light*' तेजसि प्रयुज्यते; 'for it is found to be so used' इति प्रयोगदर्शनात्; 'to be used (conventionally or by popular acceptance)' ex. by रूढ, प्रसिद्ध; ज्योतिःशब्दो ज्वलन एव रूढः (S. B. 104); दाक्षिण्यरूढेन नाम्ना (R. I. 31). 3 आचर् 1 P, व्यव-ह्र 1 P, वृत् 1 A (with loc.); *See* **Act.** 4 अभ्यस्त-परिचित-*a.* कृ 8 U. 5 (With inf.) By present tense simply; यातुं न प्रथमं व्यवस्यति, नाद्रियते &c. (S. 4) or by पूर्वं,पुरा; 'I used to sing' पुरा गायकवृत्तिरासं; 'it used to be so' एवं पूर्वं आचार आसीत्; 'to be used to' अभिज्ञ, परिचित, अभ्यस्त, अनुवृत्त, उपयुक्त; अनभ्यस्तरथचर्याः (U. 5) 'not used to sit in chariots'; 'Used to pain' दुःखाभिज्ञ, अनुभूतदुःख; 'not used to ornaments' अनुपयुक्तभूषणः (S. 4).**—s.** उपयोगः, प्रयोजनं, अर्थः, फलं,कार्यं,किं with instr.; किं तेन जातेन, कोऽर्थस्तेन जातेन &c.; *See* **Want.** 2 प्रयोगः, व्यवहारः, व्यापारः, उपभोगः, सेवनं, 'to apply to one's own u.' स्वयं उपयुज्; 'in general u.' रूढ, प्रसिद्ध, सर्वप्रयुक्त. **-ful,** *a.* उपयुक्त, हित, सोपकार, उपयोगिन्, उपकारिन्, हितकर (री *f.*). **-fully,** *adv.* अवृथा, सफलं, सोपयोगं, अमुधा. **-fulness,** *s.* उपयोगः-गिता, हितकारित्वं. **-less,** *a.* निष्प्रयोजन, निरर्थक, विफल, निष्फल, निर्गुण, निरुपयोग, व्यर्थ, अनुपयोगिन्, वृथा-मुधा in comp. **-lessly,** *adv.* वृथा, व्यर्थं, मुधा, निष्फलं. **-lessness,** *s.* अनुपयोगः, वैयर्थ्यं.

Usher, प्रति(ती)हारः.

Usual, *a.* साधारण (णी *f.*), सामान्य, व्य-(व्या)वहारिक-प्रायिक-लौकिक-सांप्रदायिक- (की *f.*) प्रसिद्ध; oft. by 'u.-ly.' **-ly,** *adv.* प्रायः, प्रायेण, प्रायशः, साधारण्येन, सामान्यतः, बहुशः.

Usufruct, *s.* फल-फलभोग-अधिकारः.

Usurp, *v. t.* बलात् ग्रह् 9 U or आत्मसात्कृ 8 U, अनधिकारेण आक्रम् 1 U, 4 P. **-ation,** *s.* बलात् आक्रमणं-ग्रहणं, बलापहारः. **-er,** *s.* बलात् ग्राहिन्; 'u. to the throne' राज्यापहारिन् *m.*

Usury, *s.* कुसीदं, कौसीद्यं, अर्थप्रयोगः, वृद्धिजीविका. **-er,** *s* कुसीदकः, वृद्ध्याजीवः, वार्धुषिकः, वार्धुषिः. **-ous,** *a.* कौसीद (दी *f.*), सवृद्धिक.

Utensil, *s.* भांडं, पात्रं, उपकरणं, भाजनं.

Uterus, *s.* गर्भकोशः, गर्भाशयः, योनि *f.* **-Uterine,** *a.* सहोदर, सोदर, समानोदर, सनाभि.

Utility, *s.* उपयोगः; *See* **Use.**

Utmost, *a.* परम, पर; 'to the u. of one's power' यावच्छक्यं, यावच्छक्तितः; 'do or try one's u.' यावच्छक्यं प्रयत् 1 A; 'u. limit' परा काष्ठा, परा कोटिः; 'this is the u. that I can do' एष मे परमो विभवः (Ka. 159).

Utopian, *a.* काल्पनिक (की *f.*), मनःकृत; 'u. scheme' कल्पना-मनः-सृष्टिः.

Utter, *a.* संपूर्ण; *See* **Complete.** 2 केवल, मात्र in comp.; (मौर्ख्यमात्रमिदं). **-v. t.** उदीर् c., व्याहृ 1 P, उदाहृ, उद्-गॄ 6 P, उच्चर् c.; *See* **Say** also. **-ance,** *s.* उच्चारः-रणं, उद्गारः, व्याहारः, उदीरणं; 'easy of u.' सुखोच्चार्य, सुबोध. **-ly,** *adv.* सर्वथा, अशेषेण, साकल्येन, संपूर्णं.

Uvula, *s.* अलि-घंटि- जिह्वा.

Uxorious, *a.* स्त्रीवश्य, भार्यासक्त, स्त्रीविधेय, दारनिरत, कामवश. **-ness,** *s.* भार्यासक्ति *f.*, भार्याधीनता.

V.

Vacant, *a.* शून्य, (fig also), रिक्त; 'with v. looks' शून्येक्षण *a.*; 'v.-minded' शून्यहृदय. 2 अस्वामिक; 'a v. throne' अराजक. **–Vacancy,** *s.* शून्यं, रिक्तं. 2 शून्यं, अस्वामिकं अधिकारपदं. **–Vacate,** *v. t.* उत्सृज् 6 P, रिच् 7 P, परि-, त्यज् 1 P. **–ion,** *s.* अनध्ययनं, अध्ययनविश्राम:-निवृत्ति *f.*, विश्रामकाल:.

Vaccine, *a.* गव्य.

Vaccinate, *v. t.* गोबीजं निविश् *c.*

Vacillate, *See* **Waver.** **–ion,** *s.* अस्थिरता, अनिश्चय:, चांचल्यं.

Vacuity, Vacuum, *s.* शून्यं, खं, रिक्तं, अवकाशं.

Vagabond, *a., s.* स्वेच्छाचारिन्, परिभ्रमिन्, यथेच्छविहारिन्. 2 अज्ञातनिवास,भ्रष्टचारिन्.

Vagary, *s.* वि-,भ्रम:, तरंग:-वृत्त *n.*, मनोलौल्यं, बुद्धिचापल्यं.

Vagrant, *See* **Vagabond.**

Vague, *a.* अनिश्चित, संदिग्ध, अनियत, अनिर्णीत, अपरिच्छिन्न. **–ness,** *s.* अनिश्चय: अपरिच्छेद:, अनिर्णय:, संदेह:, संशय:.

Vain, *a.* व्यर्थ, निष्फल, विफल, निरर्थक, मोघ, वृथा-मुधा in comp.; 'v. thoughts' वृथामनोरथा:. 2 असार, नि:सार, शून्य. 3 (**Vainglorious**) वृथाभिमानिन्, अहंकारिन्, वृथाश्लाघिन्, गर्वित; *See* **Proud. –ly,** 'in v.' *adv.* वृथा, मुधा, निरर्थकं, व्यर्थं, निष्फलं. **–Vanity,** *s.* वृथाभिमान:, मिथ्यागर्व:, अहंकार:; *See* **Pride.** 2 असारत्वं, नि:सारता, अफलत्वं, वैफल्यं, मोघता. 3 असारवस्तु.

Valediction, *s.* आमंत्रणं, अनुज्ञा, आमन्त्रणं; स्वस्तिवाद:. **–Valedictory,** *a.* स्वस्तिवाचनिक (की *f.*).

Valet, *s.* सेवक:, दास:, पार्श्वचर:.

Valetudinarian, *a., s.* रोगिन्,दुर्बल, व्याधिपीडित, व्याधितमन्.

Valiant, *a.* विक्रांत, पराक्रमवत्, उरुविक्रम, शूर, वीर; *See* **Brave. –ly,** *adv.* सविक्रमं, सपराक्रमं, शूर-वीर-वत्, साहसपूर्वकं.

Valid, *a.* सबल, बलवत्, सप्रमाण, सयुक्तिक (की *f.*), अबाध्य, न्याय्य, सत्य. **–ity,** *s.* सत्यत्वं, सिद्धि *f.*

Valise, *s.* चर्म-संपुट-पेटक:.

Valley, Vale, *s.* द्रोणी, उपत्यका, अधित्यका.

Vallum, *s.* प्राकार:, वप्र:.

Valour, *s.* विक्रम:-पराक्रम:, शौर्यं, वीर्यं. **–ous,** *a.* शूर, वीर, विक्रांत, *See* **Brave.**

Value, *v. t.* [illegible] [illegible] 10 or स्था *c.* ([illegible]). 2 मन् 4 A, बहुमन् 10, आ-कलय् 10; 'v. highly,' बहु मन्, संमन् *c.* **–s.** मूल्यं, अर्घ:; *See* **Price.** 2 माहात्म्य, गरिमन् *m.*, सारवत्ता. 3 महार्घ:, बहु-महा-मूल्यं. 4 अर्घकरणं; 'fixing the v.' अर्घसंस्थापनं. **–able,** *a.* महार्घ-र्घ, महा-बहु-मूल्य, मूल्यवत्, गुणवत्. **–s,** बहुमूल्यद्रव्यं. **–ation,** *s.* मूल्यनिरूपणं-संस्थापनं-निर्णय:.

Valve, *s.* कपा(वा) ट:-टी-टं; पिधानं.

Vampire, *s.* भूत:, प्रेत:, पिशाच:

Van, *s.* (सेना-) मुखं, अग्रभाग:, अग्रं, मूर्धन् *m.*, नासीरं, शिरस् *n.*; 'in the v.' अग्रे, पुरस्तात्, अग्रत:. 2 यानं; *See* **Cart;** 'v.-guard' अग्रानीकं, सेनामुखं, नासीरचरा: (pl.).

Vane, *s.* वायुगतिसूचकं यंत्रं.

Vanish, *v. i.* तिरोभू 1 P, तिरोधा-अंतर्धा-pass.; *See* **Disappear.** 2 वि-नश् 4 P प-वि-ली 4 A.

Vanquish, *v. t.* पराजि 1 A, पराभू 1 P, वशं नी 1 P; *See* **Humble, Subdue.** **–er,** *s.* जेतृ *m.*

Vantage,-ground, *s.* अग्रभूमि *f.* 2 उत्कर्ष:, श्रेष्ठपदं.

Vapid, *a.* विरस, नीरस, रसहीन.

Vapour, *s.* बाष्प:, धूम:; 'v. of the sky' जलबाष्प:, अभ्रं; 'v.-bath' उष्णस्वेद:. **–v. i.** वि-कत्थ् 1 A; *See* **Boast. –ous, –y,** *a.* बाष्पमय (यी *f.*), बाष्परूप. 2 असार, नि:सार.

Variegate, *v. t.* चित्र् 10, चित्रीकृ 8 U, कर्बुरीकृ, शबलीकृ; कल्माषयति (D.). **–ed,** *a.* चित्र, कर्बुर, कर्बुरित, कि(क)र्मीर, किर्मीरित, शबल, कल्माष, कल्माषित, एत, सार; 'v. colour' कर्बुरता, किर्मीर:, शबल:.

Variola, *s.* मसूरी-रिका.

Variet, *s.* भृत्य:, किंकर:. 2 वराधम:, जाल्म:.

Varnish, *s.* सुधालेप:. **–v. t.** सुधालेपेन लिप् 6 P, स्निग्धीकृ; (fig.) बाह्यशोभां कृ 8 U.

Vary, *v. t.* परिवृत् *c.*, विपर्यस् 4 U or *c.*, अन्यथाकृ 8 U, नानाविध-विविध-*a.* कृ; विपर्यासं नी 1 P; *See* **Change. –v. i.** भिद् pass, परिवृत् 1 A; विकृ pass.; oft. ex. by भिन्न, भिन्नरूप; यथोत्तमायोर्थितया मधूनां प्रयच्छंतं योरुपभिन्नेषु (K. III. 1) 'v.-es with the object in view'; &c. **–iable,** *a.* अस्थिर, चंचल, परिवृत्तिशील, अनित्य,अनवस्थित. **–iance,** *s.* भेद:, विरोध:, विप्रतिपत्ति *f.*; विवाद:, कलह:, वैरं, द्वंद्वं. 'to be at v.' विप्रति-पद् 4 A; (अत्र सूत्र विप्रतिपद्यंते); 'at v.' भिन्न, विवादपक्ष, परस्परविरुद्ध. **–iation,** *s.* परिवृत्ति *f.*, विकार:, भेद:. **–iety,** *s.* विविधता, भेद:, विशेष: in comp.; यथा वर्ण-वेष-भेद:. 2

प्रचलता, चित्रता, (of colours); 'v. of' Various, q. v. -Varied, Various, a. विविध, नानाविध-रूप-प्रकार-आकृति, अनेकप्रकार in comp.; बहुविध; 'v. talks' उच्चावचाः प्रलापाः; 'in v. ways' अनेकधा, बहुविधं, नाना. -ly, adv. बहुधा, विविधं, नाना, नानाप्रकारं, अनेकविधं.

Vascular, a. नाडीविशिष्ट-संबंधिन्.

Vase, s. कुंभः, कलशः-शः, पात्रं, भाजनं; 'a golden v.' भृंगारः, कनकालुका.

Vassal, s. प्रजा, वशवर्तिन् m., आश्रयः, परतंत्रः; *See* **Dependent**.

Vast, a. विशाल, विस्तीर्ण, विपुल, अपरिमित, सुमहत्, अतिबृहत्.

Vat, s. कुंडं, (बृहत्) भांडं.

Vaticinate, v. i. *See* **Prophesy**.

Vault, s. छदि f., विवरं, भूमिगृहं. 2 कोषकहीर्वे; 'v. of heaven' नभोमंडलं. 3 वल्गितं. -v. i. वल्ग् 1 P, प्लु 1 A.

Vaunt,-er, *See* **Boast**; 'v. ing of his might' अतिदर्पितबलः (Mr. 5), स्वबलप्रशंसः.

Veal, s. गोवत्समांसं.

Veer, v. परिवृत् 1 A, भिन्नदिशं या 2 P or व्रज् 1 P.

Vegetate, v. i. उद्भिद् pass., स्फुट् 6 P, प्र-रुह् 1 P. -ion, s. उद्भिद्,उद्भेदः, तृणादि n., तृणजाति f. -**Vegetable**, a. उद्भिद्-ज्, उद्भिज्ज, औद्भिद (दी f.). -s. (Eatable) शाकः-कं; हरितकं, शिग्रुः. -s. उद्भिद्-ज्जं, ओषधि f., तृणादि.

Vehement, a. प्रचंड, तीव्र, तीक्ष्ण, बलवत्, उग्र, सरभस, सवेग; परुष, कर्कश (of tone, speech &c.). -ly, adv. बलवत् चंडं, तीव्रं. -**Vehemence**, s. चंडता, तीक्ष्णता, रभसः, वेगः, तरस् n., संरंभः.

Vehicle, s. यानं, प्रवहणं, वाहनं, रथः, वाहः, पत्रं. 2 द्वारं.

Veil, v. t. छद् 10, आ-प्र-सं-°, अवगुंठ् 10, सं-वृ 5 U, व्यव-धा 3 U; *See* **Cover**. -s. अवगुंठनं, आवरणं, आवरणः, तिरस्करिणी. 2 आवरणं, व्यवधानं, आच्छादनं, संवरणं; 'throw the v. off' स्वरूपं प्रकाशीकृ 8 U, or आविष्कृ, वि-वृ 5 U, विवृतीकृ.

Vein, s. शि(सि)रा, धमनी, नाडि-डी f.; (of stones) रे(ले)खा. 2 वृत्ति f., भावः, मनोवृत्तिः; 'angry v.' कोपवृत्तिः. -y, a. शिर...

Vellum, s. चर्म-पत्रः-पत्रं.

Velocity, s. जवः, वेगः, रंहस् n., रभसः, तरस् n.

Venal, a. धनक्रेय, उत्कोचग्राहक. 2 पण्य in comp; 'a v. woman' पण्यस्त्री.

Vend, v. t. वि-क्री 9 A, पण् 1 A. -er, s. विक्रयिन् m. -ible, a. पण्य, विक्रेय.

Venerate, Venerable. *See* **Revere,-ed.**

Venery, s. मैथुनं, रति f., संभोगः. 2 मृगया. -**Venereal**, a. (s.) in comp.; 'v. disease' उपदंशः. 2 वाजीकर (री f.).

Venesection, s. शिराच्छेदः.

Vengeance, s. प्रतिहिंसा, प्रत्यपकारः, वैरनिर्यातन-शुद्धि f.; *See* **Revenge**.

Venial, a. मर्षणीय, क्षंतव्य,लघु, उपेक्ष्य, अल्प; oft. by उप pr.

Venison, s. मृग-हरिण-मांसं.

Venom, s. विषं, गरलं, गरं, क्ष्वेडः. -ous, a. सविष, विषाक्त, दंदशूक, विष in comp.

Vent, v. t. उत्-वि-सृज् 6 P, उत्क्षिप् 6 P. निः-सृ c., उद्गम् 1 P, उद्-गृ 6 P; *See* **Emit**. -s. छिद्रं, रंध्रं, द्वारं; 'give v. to' उदीरय् c., प्रकटयति (D.), आविष्कृ 8 U.

Ventilate, v. t. वीज् 10; *See* **Fan**. 2 प्रचारय् c., प्र-सृ c. -ed, a. प्रवात, वायुप्रवात; 'a bed in a v. place' प्रवातशयनं (M. 4). -or, s. वीजनं, व्यजनं.

Ventral, a. उदर in comp.

Ventricle, s. कोशः-षः, द्वारं.

Ventriloquist, s. मायकवादिन् m. -**Ventriloquism**, s. मायकवादः.

Venture, s. साहसं, साहसक्रिया. 2 संकट, संशयः; *See* **Danger**. -v. i. संशये निक्षिप् 6 P. 2 उत्सह् 1 A, साहसं कृ 8 U, धृष् 5 P; 'we cannot v. to state this' इति कथनकर्म साहसं कर्तुं न शक्नुमः, इति कथयितुं नोत्सहामहे; 'nothing v., nothing gain' साहसे श्रीः प्रतिवसति. -ous,-some, a. साहसिक (की f.), साहसबुद्धि.

Venus, s. शुक्रः, भार्गवः, कविः, उशनस् m., काव्यः, दैत्यगुरुः.

Veracious, a. सत्यवाच्, सत्यविद्, सत्यवादिन्, सत्यशील. -**Veracity**, s. सत्यवादित्वं, सत्यशीलता.

Veranda, s. *See* **Porch**.

Verb, s. क्रिया,-पदं. -al, a. शाब्दिक (की f.), शाब्द (ब्दी f.), शब्दरूप. 2 (Oral) वाचिक-वाचनिक (की f.), (वाचिकमित्युक्तं श्रोतुमिच्छामि Mu. 5). -ally, adv. वाचा. 2 शब्दशः, यथाशब्दं -atim, adv. यथाव्याहृतं, पदानुपदं, शब्दशः, यथाशब्दं. -ose, a. वाग्बहुल, अतिविस्तीर्ण; *See* **Prolix**. -osity,-iage, s. वाग्विस्तरः, वाक्प्रपंचः, बहुप्रपंचः.

Verdant, a. हरित, शाद्वल.

Verdure, s. हरितत्वं, हारित्यं; शाद्वः, शाद्वलता; 'clothed in fresh v. of sprouts' नवहरितसस्यांकुरवती.

Verdict, s. निर्णयः, विचारः, दंडनिर्णयः.

Verdigris, s. ताम्रकिट्ट-मलं, कलंकः.

Verge, *s.* प्रांतः, पर्यंतः, धारा; 'on the v. of' उन्मुख (खी *f.*), आसन्न in comp.; 'on the v. of ruin' विनाशोन्मुख, आसन्नलय. 2 दंडः, यष्टि *f.* —*v. i.* अव-,लंब् 1 A; by (*s.*); 'is v. ing on ruin' आसन्ननाशो वर्तते; 'when it was v. ing towards sunset' परिणतप्राये अहनि 'v. ing on 18' अष्टादशवर्षदेशीय; *See* **Border.** —**er,** *s.* दंडिन् *m.*,दंड-वेत्र-धरः.

Verify, *v. t* प्रमाणीकृ 8 U, प्रमाणयति (D.) समर्थ् 10, सत्याकृ, सत्यापयति (D.), निर्णी 1 P. —**ication,** *s.* सत्यापनं, सत्याकारः.

Verily, *adv.* सत्यं, नूनं, नियतं, नाम, खलु.

Verisimilitude, *s* संभवः. 2 सादृश्यं.

Veritable, Verity, *See* **True, Truth.**

Vermes, *s.* (pl.) कृमयः, कीटकाः. **Vermicide, —Vermifuge,** *a.* कृमि-हर-घ्न (घ्नी *f.*); —**Vermicular,** *a.* कृमिसदृश (शी *f.*), —**Vermiform,** *a.* कीटकाकृति.

Vermilion, *s.* सिंदूरं. —*a.* शोण, रक्त. —*v. t.*, 'cover with v.' सैंदूरीकृ, सिंदूरेण रंज् c.

Vermin, *s.* कृमयः (pl.), कृमिगणः.

Vernacular, *a.* जन्म in comp.; 'v. dialects' भाषा, प्राकृतभाषा. —*s.* जन्मभाषा, मातृभाषा.

Vernal, *a.* वासंत (ती *f.*), वासंतिक (की *f.*), वसंत in comp.

Versatile, *a.* चपल, लोल, लोल-मति-बुद्धि, चंचल; *See* **Fickle.** —**ity,** *s.* (बुद्धि-)चापल्यं, लौल्यं.

Verse, *s.* कविता, पद्यं, काव्यं; 'syllabic v.' वृत्तं; 'blank v.' मुक्तप्रासः. 2 श्लोकः. 3 (Portion of v.) चरणः, पादः, पदं. —**Versify,** *v. t.* पद्यानि रच् 10 or निबंध् 9 P, कवयति (D.). —**ier,** *s.* कविः, कविंमन्यः. —**ication,** *s.* श्लोक-पद्य-रचना, छंदोबंधः.

Versed, *a.* अभिज्ञ, कुशल, निपुण, प्रवीण, सुप्रतिष्ठित, अभ्यंतर, विशारद; *See* **Skilful.**

Version, *s.* **Translation,** q. v. 2 पाठांतरं, पाठभेदः.

Vertebra, *s.* पृष्ठवंशास्थि *n.* —**ae,-ted,** *a.* पृष्ठवंशयुक्त-विशिष्ट.

Vertex, *s.* शीर्षं, अग्रं, शिखरं; *See* **Top** also.

Vertical, *a.* ऊर्ध्व-उपरि-तन (नी *f.*), लंबरूप. —**ly,** *adv.* अधोमुखं, ऊर्ध्वाधरं.

Vertigo, *s.* भ्रमः; *See* **Giddiness.**

Verve, *s.* उत्साहः, आवेशः.

Very, *adv.* अति-सु pr., सातिशयं, अतीव, भूरि,नि-सु-तरां, अत्यंतं; *See* **Exceedingly;** 'v. deceitful' भूरिमाय. —*a.* ex. by demonstrative pron. with एव; 'the v. hills' त एव गिरयः; 'this v. day' अद्यैव. 2 सत्य, तथ्य. 3 मात्र in comp., केवल.

Vesicle, *s.* त्वक्-चर्म-स्फोटः.

Vesper, *s* संध्या, संध्योपासनं.

Vessel, *s.* पात्रं, भाजनं, भांडं, आधारः. 2 पोतः, समुद्रयानं, जलयानं, वहित्रं, नौः. 3 नाडी; *See* **Vein.**

Vest, *s.* वस्त्रं वेषः-षः, वसनं. —*v. t.* वेष्ट् c., परि-धा c.; *See* **Dress.** —**ed,** *a.* (in) व्यवस्थित; 'are warlike qualities v. (in any one)' किं व्यवस्थितविषयाः क्षात्रधर्मा इति (U. 5). 2 अधीन, आयत्त. —**Vestment, Vesture,** *s.* वासस् *n.*, वस्त्रं; **Dress.**

Vestal, *a.* शुद्ध, पवित्र; *See* **Chaste.**

Vestibule, *s.* देहलि-ली *f.*; *See* **Porch.**

Vestige, *s.* चिह्नं, अंकः, लक्षणं, पदांकः, पदपंक्ति *f.*, पद्धती.

Veteran, *a.*, *s.* जातानुभव, ज्ञानवृद्ध, अभ्यासवृद्ध.

Veterinary, *s.* पशुचिकित्सकः, पशुवैद्यः; (art) पशुचिकित्सा.

Veto, *v. t.* प्रति-नि-षिध् 1 P, प्रत्या-ख्या 2 P; *See* **Contradict.** —*s.* प्रति-नि-षेधः, प्रत्यादेशः.

Vex, *v. t.* बाध् 1 A, पीड् 10, क्लिश् 9 P, संतप् c., उद्विज् c., अर्द् 1 P or c. 2 प्रकुप् c., क्रोधं उद्दीप् c. —**ation,** *s.* क्लेशः, दुःखं, पीडा, कष्टं, बाधा, आयासः, संतापः. 2 प्रकोपनं, क्रोधोद्दीपनं. —**atious,** *a.* बाधक, क्लेशकर-पीडाकर -(रि *f.*), उद्वेजकर, संतापक. —**ed,** *a.* दुःखित, संतापित, अर्दित, &c. —**edly,** *adv.* सक्रोधं, सोद्वेगं.

Viand, (V. s.) *s.* अन्नं, भक्ष्यं, सिद्धान्नं.

Viaticum, *s.* पाथेयं, पथि भोज्यं.

Vibrate, *v. i.* दोलायते (D.), कंप् 1 A, स्फुर् 6 P, भ्रम् 1, 4 P. —*v. t.* भ्रम् c., इतस्ततः चल् c., वि-धू 5, 9 U. —**ion,** *s.* आंदोलनं, दोलायितं, स्फुरणं, कंपः, भ्रमणं.

Vicar, *s.* प्रतिनिधिः. —**ious,** *a* प्रतिनिधिक.

Vice, *s.* अधर्मः, पापं, पापाचरणं, असदाचारः, व्यभिचारः. 2 दोषः, दुर्गुणः, व्यसनं. 3 (Instead of) Ex. by स्थाने or प्रतिनिधिः oft by उप pr.; 'viceroy' 'vicegerent,' राजप्रतिनिधिः, राजस्थाने स्थितः; 'v.-president' उपाध्यक्षः. —**Vicious,** *a.* दुष्ट, दुराचार, अपथप्रवृत्त, व्यसनिन्, दुरात्मन्, पापवृत्त, दुर्वृत्त, दुश्चरित, कलुषितवृत्ति. —**ly,** *adv.* दुष्टतया, दुर्वृत्ततया, दुष्टभावेन.

Vicinage, Vicinity, *s.* संनिधिः, सांनिध्यं, संनिकर्षः.

Vicissitude, *s.* आ-परि-वृत्ति *f.*, विपर्ययः, परिवर्तः, संक्रमः; 'Oh! how rarely seen (by mortal prescience) the strange v. s of human life' अहो अलक्षितोपागिपाताः दुरवगमा लक्ष्मीचलकृतान्तविलासमतिपरिवर्तक्रमा भवन्ति (Mu. 6).

Victim, *s.* बलिः, उपहारः, पशुः, यज्ञपशुः; (fig.) *See* **Prey.** **-ize,** *v. t.* उपहारीकृ 8 U; *See* **Sacrifice.**

Victor, Victorious, *s., a.* वि-, जयिन्, जैत्र (त्री *f.*), जित्वर (री *f.*), जिष्णु, प्राप्तजय. 2 जय-मङ्गल, जयावह. **-iously,** *adv.* सविजयं, जयपूर्वं. **-y.** *s.* वि-, जयः; 'gain v.' विजयं-लभ् 1 A, or प्राप् 5 P, वि-जि 1 A; 'v. to your Majesty' जयतु जयतु देवः.

Victual, *v. t.* खाद्यसामग्रीं उपकॢप् c. **-s.** (V. s) खाद्य-भक्ष्य-सामग्री, भक्ष्यसंभारः. **-ler,** *s.* भक्ष्यविक्रयिन् *m.* **-ling,** *s.* अन्न-विक्रयः, भक्ष्यव्यवहारः.

Vie, (with) *v. i.* स्पर्ध् 1 A, जि desid. (जिगीषति); *See* **Rival;** अहमहमिकया प्रणामलालसाः (Ka. 81) 'v.-ing with each other for saluting'.

View, *v. t.* सं-, ईक्ष् 1 A, निर्वर्ण् 10, आ-अव-लोक् 1 A, 10, निरीक्ष्; *See* **See.** **-s.** आलो-कनं, समीक्षणं, दर्शनं, दृष्टि *f.*; 'point of v.' दृष्टिः, पक्षः; 'from a worldly (practical) point of v.' लोक-व्यव-हार-दृष्ट्या; शास्त्रदृष्ट्या &c.; इत्येवलोक-दृष्ट्या निदर्शितं शास्त्रदृष्ट्या न पराङ्मुखते (S. B. 508); 'from this point of v.' अस्मिन् पक्षे. 2 मतं, बुद्धि *f.*, मति *f.*, दृष्टिः. 3 हेतुः, आशयः, अभिप्रायः, उद्देशः; 'with what v.' किमुद्दिश्य, केन हेतुना, किमभिप्रेत्य; 'with this v.' अस्माद्धेतोः, एतदर्थं; 'of narrow v. s' कृपणबुद्धि-दृष्टि; 'of liberal v. s' उदारधीः. 4 दृक्पातः-विषयः, नयनगोचरः प्रदेशः; 'having in v.' दृष्टिगोचरवर्तिन्. **-less,** *a.* अदृश्य.

Vigil, *s.* जागरणं, प्र-, जागरः, रात्रिजागरः. **-ance,** *s.* अवधानं, अवहितता, दक्षता, जाग-रूकता. **-ant,** *a.* जागरूक, अवहित, दक्ष, सावधान, अप्रमत्त. **-antly,** *adv.* अप्रमादेन, सावधानं.

Vigour, *s.* वीर्यं, बलं, शक्ति *f.*, ओजस् *n.*, सत्त्वं, तेजस् *n.*, प्रभावः, पौरुषं; *See* **Strength.** **-ous,** *a.* प्रबल, ओजस्विन्, महासत्त्व, ऊर्जस्वल, वीर्यवत्; *See* **Strong;** सोत्साह, सप्रयत्न. **-ously,** *adv.* बलं, बलवत्, तरसा, ओजस्वितया; सवीर्यं. महा-प्रयत्नेन, सोद्यमं, सोत्साहं.

Vile, *a.* अधम, नीच, अधन्य, नि-अप-कृष्ट. **-ness,** *s.* नीचता &c.; *See* **Mean,** &c. **-Vilify,** *v. t.* परि-वद् 1 A, कुत्स् 10, आ-क्षर् c.; *See* **Traduce, Libel.** **-er, -ication:** *See* **Calumny.**

Villa, *s.* ग्राम्यं गृहं, विनोदस्थानं.

Village, *s.* ग्रामः, निवसथः; 'head of a v.' ग्रामणीः, ग्रामेशः, ग्रामाध्यक्षः. **-a.** ग्राम्य, ग्रामीय ग्रामीण, ग्राम in comp. **-er,** ग्रा-मिन् *m.*, ग्रामिकः, ग्रामवासिन् *m.*, ग्रामीणः, ग्रामस्थः, ग्राम्यजनः.

Villain, *s.* दुर्वृत्तः, अपसदः affixed, (नरा-पसदः), चांडालः, खलः, अधमः, दुरात्मन् *m.*; *See* **Rascal** also. **-ous,** *a.* दुर्वृत्त, दुष्टतम, अधम &c.

Villein, *s.* दासः. प्रजा.

Vim, *s.* शक्ति *f.*, सत्त्वं, बलं.

Vindicate, *v. t.* रक्ष् 1 P, प्रमाणीकृ 8 U, समर्थ् 10, प्रति-पद् c., स्था c. (स्थापयति); (from blame) शुध् c., निर्दोषीकृ. 2 निर्वह् 1 P or c.; निर्व्यूढस्तेपत्यस्नेहः (U. 3) 'thy parental affection has been v.-ed'. **-ion,** *s.* रक्षणं, प्रतिपादनं; स्थापनं; निर्वाहः; दोषमुक्ति *f.*, परिशोधनं. **-or,** *s.* रक्षकः, समर्थयितृ *m.*

Vindictive, *a.* प्रतिकारपरायण-शील, वैर-साधनपर, वैरनिर्यातनोत्सुक; क्रोधन, कोपिल; अक्षमिन्, असहिष्णु.

Vine, *s.* द्राक्षा, -लता. **-ous,** *a.* सुरामय (यी *f.*). **-Vinegar,** *s.* शुक्तं, शौक्तिकं. **-Vineyard,** *s.* द्राक्षाक्षेत्र-वाटिका. **-Vin-tage,** *s.* द्राक्षाः, द्राक्षाफलं; 'v.-time' द्राक्षावचयकालः. **-Vintner,** *s.* शौण्डिकः, सुराजीविन् *m.*

Violate, *v. t.* दुष् c. (a woman). 2 अति-क्रम् 1 U, 4 P, उल्लंघ् 1 A, 10, अतिचर् 1 P, व्याहन् 2 U, लुप् c., भंज् 7 P, 'for fear of v.-ing your word' प्रतिज्ञाभंग-भीरुणा (त्वया). 3 भंज्, पराजि 1 A. **-ion,** *s.* अतिक्रमः, भंगः, उल्लंघनं, लोपः, -षणं. 2 आ-, धर्षणं-णा. **-or,** *s.* धर्षकः. 2 उल्लंघकः.

Violent, *a.* प्रचंड, प्रबल, तीव्र, उग्र, महावेग, उग्र. 2 साहसिन्, साहसिक (की *f.*), तीक्ष्ण-कर्मन्; 'a v. death' अपमृत्युः. **-ly,** *adv.* प्रसह्य, प्रसभं, तरसा, वेगेन, बलात्कारेण, बलवत्, उच्चंडं, तीव्रं, गाढं, अति-सु pr.; 'v. in love' गाढानुराग. **-Violence,** *s.* बलं, तरस् *n.*, जवः, वेगः. 2 बलात्कारः; साहसं, प्रमाथः, प्रसभं.

Violet, *s.* पाटलं. 2 (Colour) नीललोहितः.

Violin, *s.* सा(शा)रंगी, पिनाकी.

Viper, *s.* दंदशूकः, अहिः; *See* **Snake.**

Virago, *s.* स्त्रीयोधी, पुरुषवृत्तिः, ऋषभी.

Virgin, *s.* कुमारी, कन्या, तरुणी, अक्षता, अक्षत-अविद्ध-योनिः, पुरुषास्पृष्टा. **-a.** कौमार (री *f.*), (*s.*) in comp. 2 वि-, शुद्ध, अक्षत. **-ity,** *s.* कौमारं, कुमारीत्वं, पुरुषास्पर्शः. 2 विशुद्धता.

Virgo, *s.* कन्या, -राशिः.

Viridity, *s.* *See* **Verdure.**

Virile, *a.* पौरुष (षी *f.*), पौरुषेय (यी *f.*). पुरुष in comp. **-ity,** *s.* पुंस्त्वं, पुरुषत्वं, पौरुषं.

Virtue, *s.* धर्मः, पुण्यं, सुकृतं, सदाचारः, साधुता. धर्मशीलता नीति *f.* 2 — —

-गुणः. 2 शक्तिः f., बलं, प्रभावः, सामर्थ्यं; 'by v. of' बलात्, बलेन, प्रभावेण. -Virtual, a. वास्तविक (की f.), better by 'v.-ly'. -ly, adv. वस्तुतः, यथार्थतः, अर्थतः. -Virtuous, a. धार्मिक (की f.), पुण्य-धर्म-शील, धर्मपर-परायण, साधु, पुण्यात्मन्, सुकृतिन्, पुण्यभाज्, न्यायाचार, साधुवृत्त, सदाचार, सच्चरित; oft. by सत्; सती, सज्जनः &c. 2 (Of acts) धर्म्य, पुण्य, साधु. -ly, adv. धर्मतः, धर्मेण, सदाचारतः.

Virulent, a. उग्र, कटु, तीक्ष्ण, चंड; See Malignant, Sharp.

Virus, s. विषं.

Visage, s. आस्यं, आननं, वदनाकृति f., वदनाकारः; 'with sad v.' विषण्णवदन

Viscera, s. अंत्राणि (pl.).

Viscid, Viscous, a. सांद्र, श्यान, शीन; पिच्छल, स्निग्ध; 'v. fluid' दानजलं, दानं (of an elephant).

Visible, a. दृश्य, दृग्गोचर, प्रत्यक्ष, दृष्टिविषय, नयनपथवर्तिन्, नेत्रविषयगत, व्यक्त, सुप्रकाश, चक्षुर्ग्राह्य, and sim comp. -Visibly, adv. प्रत्यक्षं, प्रत्यक्षतः, साक्षात्.

Vision, s. दृष्टि f., चक्षुरिंद्रियं. 2 छाया, आभासः, माया, मनःसृष्टि f., कल्पना. 3 स्वप्नः, स्वप्नदर्शनं. -ary, a. अवास्तव (वी f.), मानसिक-काल्पनिक (की f.), मनःसृष्ट-कल्पित.

Visit, s. दर्शनं, अभ्यागमः. 2 साक्षात्कारः; 'pay a v. to' द्रष्टुं अभ्यागम् 1 P. -v. t. दृश्, अभि-इ 2 P, अभ्युपगम्, द्रष्टुं गम् or या 2 P. 2 साक्षात्कृ 8 U. 3 (With punishment) दंड् 10; 'v. a lover' अभि-सृ 1 P (कामुकं). -ant, -or, s. अभ्यागतः, गृहागतः. -ation, s. अभ्यागमनं. 2 दृष्टिपातः.

Vista, s वीथि-थी f., तरुपंक्ति-श्रेणी f.

Visual, a. चाक्षुष (षी f.), दृष्टिगत, चक्षुस्-नेत्र in comp.; 'v. organ' चक्षुरिंद्रियं.

Vital, a. आवश्यक (की f.). 2 प्राणभूत, जीव-प्राण in comp.; 'v. air' प्राणवायुः; 'v. principle' जीवात्मा; 'v. part' मर्मन् n.; 'v. -s' मर्माणि; 'touching (rending, piercing.) the v. s.' मर्मतुद, मर्मस्पृश्, मर्माणि कृंतत्. -ity, s. जीवनं, चेतनत्वं, सजीवत्वं, चेतना; प्राणः, जीवः, जीव-प्राण-शक्ति f.

Vitiate, v. t. Corrupt, q v. -ion, s. दूषणं, भ्रंशनं.

Vitrious, a. काचज, काचाभ, काचमय (यी f.). -Vitrify, v. t. काचसात्कृ 8 U.

Vitriol, s. (Blue) तुत्थांजनं, शिखिग्रीवं, वितुन्नकं, मयूरकं, कर्परी; (green) कासीसं.

Vituperate,-ion, See Censure.

Vivacious, a. प्रफुल्ल, सोत्साह, सतेजस्. -ness, -Vivacity, s. उत्साहः, तेजस्विता, प्रफुल्लता, उल्लासः.

Viva-voce, See Orally.

Vivid, a. सुस्पष्ट, विशद, परिस्फुट.

Vivify, v. t. जीव् c., सजीवीकृ 8 U.

Viviparous, a. जरायुज, जीवज. 2 सजीवप्रसव.

Vixen, s. कलहप्रिया, कर्कशा, चंडी.

Vocable, s. शब्दः, वाक्यं, वचनं.

Vocabulary, s. अभिधानं, कोशः, शब्दार्णवः, शब्दसंग्रहः-कोशः.

Vocal, a. वाचिक (की f.), वाङ्मय (यी f.), वाग्जात. 2 वाणीयुक्त, वाग्विशिष्ट. 3 सुस्वर, मधुर; 'v. music' कंठगीतं.

Vocation, s. वृत्ति f., व्यवसायः, नियोगः, व्यापारः.

Vocative, s. संबोधनं, संबुद्धि f.

Vociferate, v. i. उच्चैः आक्रंद् 1 P, उत्क्रुश् 1 P, उद्-घुष् 10. -ion, s. आक्रोशः, उद्घोषः. -Vociferous, a. महाशब्द, सकोलाहल, उद्घोषण. -ly, adv. महाशब्देन, उद्घोषेण.

Vogue, s. व्यवहारः, प्रवृत्ति f., प्रचारः, रीति f., क्षुण्णा पद्धतिः; 'it is not in v. here' अत्र नेदृशो व्यवहारः; 'being long in v.' चिरप्रवृत्त.

Voice, s. स्वरः, स्वनः, नादः, शब्दः, वाणी, वचनं, वाच् f., कंठध्वनिः-स्वरः. 2 मतं, अभिप्रायः; 'with one v.' एकचित्तीभूय, ऐकमत्येन; 'cracked v.' भग्नस्वरः; 'active v.' कर्तृवाच्यं; 'passive v.' कर्मवाच्यं; 'neuter v.' भाववाच्यं.

Void, a. शून्य, रिक्त. 2 असिद्ध, अप्रमाण, अकिंचित्कर (री f.), निरर्थक. 3 Destitute, Devoid, of q. v. -s. शून्यं, शून्यस्थानं. -v. t. रिच् 7 P or c., शून्यीकृ. 8 U. 2 निष्फलीकृ. 3 (Excrement) उत्सृज् c., विउत्-सृज्, उत्-सृ 6 P. -able, a. विसर्जनीय, परित्यक्तव्य.

Volatile, a. वायुपरिणामशील. 2 चंचल, लोल; See Fickle. -ity, s. चापल्यं, चांचल्यं.

Volcano, s. ज्वालामुखः, आग्नेयगिरिः.

Volition, s. संकल्पः, इच्छा; See Will.

Volley, s. वर्षः, (शिलावर्षः, शरवर्षः &c.), वृष्टि f., -पातः.

Voluble, a. चंचल, चपल. 2 (Of tongue) वाचाल, चपलजिह्व. -Volubility, s. वाक्चापल्यं.

Volume, s. खंडः-डं, भागः, पुस्तकं (when the sense is clear). 2 अंतर्गतं घनफलं. 3 आवलि-ली f., पटलं, राशिः, संहति f. -Voluminous, a. विस्तीर्ण, बहुपुस्तक.

Voluntary, *a.* ऐच्छिक-स्वाच्छन्दिक (की *f.*), इच्छा-मति-पूर्व; better ex. by 'v.-ily.' **-ily,** *adv.* यदृच्छया, इच्छापूर्वकं, स्वेच्छातः, प्रकाम-कामं, आत्मसंतोषेण. **-Volunteer,** *v. t.* अयाचितं उपानी 1 P or कृ c. (अर्पयति) or दा 3 U or कृ 8 U. **-s.** स्वाच्छन्दिकः युयुत्सुः, स्वेच्छासैनिकः.

Voluptuary, Voluptuous, *s., a.* विषयासक्त, भोगनिरत, इंद्रियसुखासक्त, विषयिन्; *See* **Sensual.**

Vomit, *v.* उद्-,वम् 1 P, उद्-गॄ 6 P, छर्द् 10, उत्क्षिप् 6 P. **-s.** वांतं. **2** वमनं (emetic). **-ing,** *s.* वमनं, वमः-मि *f.*, वमथुः, प्रच्छर्दिका. **-ive,** *a.* वमन (नी *f.*), वांतिकर (री *f.*), वांतिकृत्.

Voracious, *a.* घस्मर, गृध्नु, अतिलोलुप, औदरिक (की *f.*); *See* **Gluttonous.**

Vortex ,*s.* भ्रमि *f.*, आवर्तः.

Votary, *s.* भक्तः, उपासकः, पूजकः; आश्रितः.

vote, *s.* संमति *f.*, संमतं. **-v.** *i.* संमतिं-अनुमोदनं-दा 3 U, मतं प्रकाश् c.; संमतिपूर्वं वृ 5 U or नियुज् 7 A, 10 or दा.

Votive, *a.* संकल्प-संबंधिन्-कृत.

Vouch, *v. t.* साक्षीकृ 8 U, प्रमाणीकृ, प्रमाणं दा 3 U. **2** दृढीकृ, द्रढयति (D.). **-er,** *s.* प्रमाणपत्रं-लेखः, साधनपत्रं-लेखः, आगमः.

Vouchsafe, *v. t.* वि-तॄ 1 P, कृपया दा 3 U; (with inf.) प्र-सद् 1 P; *See* **Condescend, Please;** भगवान् मारीचस्ते दर्शनं वितरति (S. 7) 'v.s thee an audience' **2** अनु-ज्ञा 9 U.

Vow, *s.* व्रतं, संकल्पः, प्रतिज्ञा, शपथः, नियमः; 'under a v.' व्रतबद्ध, धृतव्रत, संकल्पबद्ध. **-v.** प्रति-ज्ञा 9 A. प्रतिज्ञां कृ 8 U or आवह् 1 P, सशपथं-सप्रतिज्ञं वद् 1 P or अभि-धा 3 U, (*Say,* q. v.); 'he has v. ed to destroy us' अस्मद्विनाशे कृतसंकल्पोसौ.

Vowel, *s.* स्वरः, अच् *m.*, अज्वर्णः.

Voyage, *s.* जलयात्रा यानं, समुद्रयानं, संयात्रा. **-v.** Ex. by कृ with (*s.*) पोतेन गम् 1 P. जलवर्त्मना गम्. **-er,** *s.* सांयात्रिकः, जलयात्रिकः.

Vulgar, *a.* ग्राम्य, असभ्य, अश्लील, अशिष्ट; प्राकृत, लौकिक (की *f.*). **-ism,** *s.* ग्राम्यरीतिः. **2** ग्राम्यशब्दप्रयोगः. **-ity,** *s.* असभ्यता, अश्लीलता. **-ly,** *adv.* साधारणतः, लौकिकरीत्या. **2** असभ्यरीत्या, ग्राम्यतया. **-ize,** *v. t.* ग्राम्यीकृ.

Vulnerable, *a.* भेद्य, धृष्य, वेध्य, 'v. point' रंध्रं, छिद्रं, मर्मन् *n.*; आत्मोद्धारप्रमेयो रंध्रं रंध्रेषु प्रहरन् रिपून् (R. xviii. 61) 'guarded against his own v. points' &c.

Vulpine, *a.* धूर्त, शृगालवत्.

Vulture, *s.* गृध्रः, दाक्षाय्यः.

W

Wad, *s.* चूर्णरोधनी.

Waddle, *v. i.* हंसवत् गम् 1 P or चर् 1 P.

Wade, *v. i.* प्लु 1 P, कष्टेन गम् 1 P, कष्टेण पारं गम्.

Waft, *v. t.* वह् 1 P or c., उत्क्षिप् 6 P; कमलवाही मालिनीतरंगाणां (S. 3); पुष्परेणूत्किरैर्वातैः (R. i. 38); (boat &c.) वह् c., प्रणुद् c., प्रचुद् 10, प्रेर् c.; *See* **Drive.** **-v. i.** प्लु 1 A, वायुना वह्-नी-pass.

Wag, *v. t.* सं-,चल् c., वि-,धू 5, 9 U, विक्षिप् 6 P. 'w. ging the tail' लांगूलचालनं-विक्षेपः-विधुति *f.* **-v. i.** चल् 1 P, धू pass. **-s.** परिहासवादिन् *m.* **-gish,** *a.* *See* **Witty.** **-Wag-tail,** *s.* खंजनः.

Wage, *v. t.* (War) विग्रह् 9 P, युद्धं आरभ् 1 A.

Wager, *s.* ग्लहः, पणः. **-v.** ग्लह्-पण् 1 A, (with gen. of thing staked).

Wages, *s.* वेतनं, भृति *f.*, मूल्यं, निर्वेशः, पणः; *See* **Hire.**

Wagon, *s.* प्रवहणं, यानं, शकटः-टं, चातुरं. **-er,** *s.* शाकटिकः, शकटवाहः, चातुरिकः.

Waif, *s.* अज्ञातस्वामिकं द्रव्यं.

Wail,-ing, *See* **Lament,-ation.**

Wain, *s.* गोवहनं, शकटः-टं.

Wainscot, *s.* भित्तिपट्टलं.

Waist, *s.* मध्यः-ध्यं, मध्यमः-मं, कटि-टी *f.*, कटि-देशः; 'w.-coat' कटिवस्त्रं.

Wait, *v. i.* स्था 1 P; (for) प्रति-ईक्ष् 1 A, अनु-प्रति-पा c. (पालयति) (of time and persons); 'w. for some time' कालः कश्चित्प्रतीक्ष्यतां (K. ii. 54); मां प्रतिपालय &c.; सह् 1 A, क्षम्,(of time only) (द्वित्राण्यहान्यर्हसि सोढुमर्हन् (R. v. 25); स्फुलिंगावस्थया वह्निरेधापेक्ष इव स्थितः (S.7) 'here is fire in the state of a spark (only) w. ing for fuel (to blaze up)'; (on or upon) उप-स्था 1 A, उप-अनु-आस् 2 A, उप-सेव् 1 A, उप-चर् 1 P; 'w. at table' परिविष् c. **-er,** *s.* सेवकः, परिवेषकः, परिवेष्टृ *m.*, (at table).

Waive, *v. t.* परि-,त्यज् 1 P; *See* **Abandon.**

Wake, *v. t.* प्र-बुध् c., जागृ c. **-v. i.** प्र-विबुध् 4 A, जागृ 2 P. **-s.** जागरणं, जागरः, प्रबोधः-धनं. **2** पद्धतिः; 'follow in the w. of' पद्धतिं प्रतिपद् 4 A; *See* **Tread.** **-ful,** *a.* (lit.) रात्रिजागर, निद्राविमुख, विनिद्र, उन्निद्र; जागरूक, दक्ष, अवहित, सावधान. **-fulness,** *s.* जागरः-रणं, अस्वापः, अस्वप्नः, अनिद्रा, प्रबोधः, जागरूकता. **2** दक्षता, अवधानं, &c.

Walk, *v. i.* (पद्भ्यां) चर्-चल्-गम् 1 P, परि-,क्रम् 1 U, 4 P, पादाभ्यां या 2 P &c.; 'w. about', 'w. to and fro' परिक्रम्, इतस्ततः भ्रम् 1, 4 P; (for pleasure) वि-हृ 1 P; 'w. away,-off' अपसृ 1 P, अप-परा-क्रम्-गम् &c. **-s. -ing,** *s.* पादचारः-गमनं; 'w. about' परिक्रमः-मणं; 'taking a w.' विहारः, विहरणं, (वायुसेवनार्थं) परिक्रमणं. **2** गमनागमनस्थानं; अध्वगमार्गः. **-er,** *s.* पादचारिन्, पा(प)दगः.

Wall, *s.* भित्ति *f.*, कुड्यं; 'enclosing w.' प्राकारः, वरणः, सालः, प्राचीरं; 'take the w. of' अग्रस्थानं आ-सद् c.; 'go to the w.' अव-सद् 1 P, अवसन्न-उच्छिन्न-*a.* भू 1 P; 'drive to the w.' अव-सद् c., उच्छिद् 7 P. **-v. t.** प्राकारेण आ-वृ 5 U.

Wallet, *s.* भस्त्रा; क्षुद्रकोषः.

Wallow, *v. i.* लुट् 6 P, लुट् 4 P; क्रीड् 1 P.

Walnut, *s.* अक्षोटः, अक्षोटं (fruit).

Wan, *a. See* **Pale.**

Wand, *s.* दंडः, यष्टि *f.*

Wander, *v. i.* परि-,भ्रम् 1, 4 P, अट् 1 P, वि-चर् 1 P, परि-,क्रम् 1 U, 4 P; 'w. from' भ्रंश् 1 A, 4 P, च्यु 1 A. **-s., -ing,** *s.* परि-,भ्रमणं-अटनं. **-er,** *s.* परिभ्रमकः, भ्रमिन् *m.*

Wane, *v. i.* परि-,क्षि 1 P or pass., ह्रस् 1 P; *See* **Decay Decline. -s.** क्षयः, ह्रासः. **-ed,** *a.* परि-क्षीण, क्षीणकल, प्राप्तक्षय, निष्कल, कलाशेष (चंद्रः). **-ing,** *a.* क्षयिन्, क्षय in comp.; 'w. period' क्षयकालः, कृष्णपक्षः, बहुलः, तामिस्रपक्षः.

Want, *v.* अपेक्ष् 1 A, आ-,कांक्ष् 1 P, इष् 6 P; gen. ex. by, कार्यं, प्रयोजनं, अर्थः, किं, (with gen. of that which wants and instr. of thing wanted) ; 'I do not w. this house' ममानेन गृहेण न कार्यं, न प्रयोजनं &c.; 'why do you w. to see her' किं तया दृष्टया (S. 2). **2 Wish,** q. v. **3** परि-,हा pass.; हीन, रहित, निर् in comp.; आर्यस्य सुविहितप्रयोगतया न किमपि परिहास्यते (S. 1) 'nothing will be w. ing' &c.; 'w. ing in courage' शौर्यहीन, निर्वीर्य, &c.; 'he w.-s. wisdom स निर्बुद्धिः, ज्ञानरहितः. **-s.** अपेक्षा, प्रयोजनं, कार्यं, आकांक्षा. **2** अभावः, विरहः, अप्राप्ति *f.*, राहित्यं, हीनता. **3** न्यूनता, ऊनत्वं, अपचयः. **4** दारिद्र्यं, धनाभावः, दुर्गति *f.*, कृच्छ्रं; 'come to or reduced to w.' दारिद्र्योपहत, भाग्यक्षयपीडितां दशां प्रपन्न (Mr. 1). **-ing,** *a.* ऊन, न्यून, विकल; *See* **Deficient.**

Wanton, *a.* विलासवत्, विलासिन्; 'w. sport' विलसितं *See* **Playful. 2** अनियंत्रित, निर्मर्याद, स्वेच्छाप्रवृत्त, लोल, (स्वभावलोल); स्वैरिन्, स्वेच्छाचारिन्; काम in comp.: 'a w. woman' पुंश्चली, स्वैरिणी, बंधकी. **3** ज्ञानतः-कामतः-कृत, बोधपूर्वं कृत. **4** प्रचुर, विपुल. **-v. i.** विलस् 1 P, क्रीड् 1 P, वि-भ्रम् 1, 4 P **-ly,** *adv.* सविलासं; निर्यंत्रणं, स्वैरं, स्वेच्छया, यथाकामं; कामतः. **-ness,** *s.* विलासः, कामचारः; न कामचारो मयि शंकनीयः 'do not suspect me of w.'

War, Warfare, *s.* विग्रहः, संप्रहारः, वैरारंभः, वैरं, संग्रामः, युद्धं, रणं, (a particular battle); 'w.-cry' सिंहनादः, क्ष्वेडा; 'w.-horse' वारकीरः. **-v. i.** विग्रह् 9 P, युध् 4 A, कृ with (*s.*). **-like,** *a.* रणप्रिय, युयुत्सु, युद्धदुर्दम; रणोत्सुक, रणवीर-शूर; 'w. qualities' क्षात्रधर्माः; 'w. tribe' क्षत्रियजातिः. **2** सांग्रामिक-सामरिक -(की *f.*),

Warble, *v.* कूज् 1 P, वि-रु 2 P.

Ward, *s.* रक्षा. **2** रक्षितः पुरुषः, आश्रितः; रक्षकाधीनः, रक्ष्यः. **3** विभागः. **-v. t.** वार् 10 or वृ c., नि-प्रति-°, निरुध् 7 U, निरस् 4 U, नि-प्रति-षिध् 1 P, प्रति-हन् 2 P, व्यप-ऊह् 1 U. **-en,** *s.* रक्षकः, रक्षापुरुषः. **-er,** *s.* रक्षकः, दौवारिकः, द्वाःस्थः.

Wardrobe, *s.* वासांसि (pl.); वस्त्रसमूहः. **2** वस्त्राधानं-आधारः.

Ware, Wares, *s.* पण्यं, पण्यद्रव्यं; 'w.-house' पण्यागारं, पण्याधानं, पण्यशाला.

Warm, *a.* तप्त, उष्ण, चंड, घर्म in comp.; fig.) तीक्ष्ण, चंड, सोत्साह. **2** घर्मार्त, आतपाक्रांत; 'grown w.' **Angry,** q. v. **-v. t.** तप् c., ईषत् तप्; 'w. oneself' (in the sun) सूर्यातपं सेव् 1 A, (सेवयेत्पृष्ठतोऽर्कं H. 2); 'w. oneself at the fire' अग्न्यातपं सेव्. **-ly,** *adv.* सोत्साहं, सस्नेहं, उष्णं &c. **-ness,-th,** *s.* तापः, उत्तापः, उष्मन् *m.*: 'w. of wealth' वित्तोष्मा. **2** चंडता, तीक्ष्णता. **3** उत्साहः; 'w. of affection' स्नेहातिशयः.

Warn, *v. t.* (पूर्वं) प्र-अनु-बुध् c., उप-दिश् 6 P, अनु-शास् 2 P. **2** सूच् 10, निर्दिश्, वि-ज्ञा c. (ज्ञापयति); 'I w. ed him of the impending danger' प्रत्यासन्नापदं तं प्राबोधयं; oft. by **Beware,** q. v.; अवहितो भव यद्यापत्प्रत्यासन्ना. **-ing,** *s.* प्रबोधनं, उपदेशः.

Warp, *v. t.* आ-वृत् c., संकुच् 1 P; (fig.) कलुषीकृ, दुष् c. (दूषयति). **-v. i.** आवृत् 1 A, संकुच् pass.

Warrant, *s.* प्रमाणं, अधिकारः; (written) आज्ञा-अधिकार-पत्रं. **-v. t.** प्रमाणं धा 3 U, प्रमाणीकृ 8 U, अधिकृ c.; *See* **Sanction. -ed,** *a.* सप्रमाण, साधार. **-y,** *s.* प्रमाणपत्रं.

Warren, *s.* शशकनिलयः.

Warrior, *s.* भटः, योधः, योद्धृ *m.*, वीरः, रथिन् *m.*, विक्रांतः; *See* **Hero, Soldier;** 'w. s on the enemy's side' प्रतिभटः.

Wart, *s.* किणः, चर्मकीलः-लं, अधिमांसं.

Wary, *a.* सावधान, अप्रमत्त, दक्ष; *See* **Careful.**

Wash, *v. t.* प्र-,क्षल् 10, प्र-मृज् 2 P or c., सिच् 3 U, अव-निज्-°, धाव् 1 U, 10; 'w. the mouth (after meals)' उपस्पृश् 6 P. **-s., -ing,** *s.* धावनं, प्र-,क्षालनं, मार्जनं, अवसेकः, निर्णेकः. 2 आलेपः, वि-प्र-लेपः-पनं. **-ed,** *a.* प्रक्षालित, निर्णिक्त, धौत, धावित, मार्जित &c. **-y,** *a.* जलधर्मक. **-Washerman,** *s.* रजकः, धावकः, निर्णेजकः, (रजकी, रजकवधू *f.*).

Wasp, *s.* वरटा, गंधोली. **-ish,** *a.* कर्कशस्वभाव, वरटाशील.

Waste, *v. t.* क्षि 1, 5 P or c., अप-सृज् c., नश् c., क्षै c. (क्षपयति), ह्रास-अर्थ-नी 1 P, अप-चि 5 U, व्यय् 10 (व्ययपति). 2 (Away) मुधा-व्यर्थ-कृ 1 P or गम् c., वि-क्षिप् 6 P. **-v. i.** परि-,क्षि-परिहा-अपचि-pass., क्षयं-नाशं-लयं या 2 P or गम् 1 P, विनश् 4 P, अवसद् 1 P, ह्रस् 1 P, क्षै 1 P; (in strength) अंगैः परिहा pass.; *See* **Lean.** **-s.** क्षयः, नाशः, अपचयः, व्ययः, ह्रासः, अवसादः. 2 अपव्ययः, वि-क्षेपः, हरणं; 'w. of time' कालक्षेपः-नाशः-हरणं-यापनं; 'w. of breath' वाग्व्ययः-क्षेपः. 3 (Land) खिलं,-भूमि *f.*, मरुभूः. **-a.** उच्छिष्ट, निःसार, निर्गुण. 2 निर्जन, शून्य, खिल, अप्रहत, जंगल; 'lay w.' उप-द्रु 1 A, उप-द्रु 1 P, बाध् 1 A, पीड् 10. **-ed,** *a.* क्षि-, क्षीण, क्षाम, अपचित, &c. **-ful,** *a.* अपव्ययिन्, वृथाव्ययिन्, व्ययशील. **-ing,** *a.* क्षीयमाण, क्षयिन्. **-Wastepipe,** *s.* उच्छिष्टजलनाली, परि(री)वाहः.

Watch, *v. t.* रक्ष् 1 P, प्रति-,पा c. (पालयति); *See* **Protect.** 2 निरूप् 10, निरीक्ष् 1 A, अवेक्ष्. 3 उपास् 2 A, उप-स्था 1 A; 'w. over' अधि-इ 1 P. **-v. i.** जागृ 2 P, (fig. also), रक्षार्थं जागृ. 2 अव-धा 3 U. अवहित-सावधान-*a.* भू; 'w. for' अपेक्ष्, प्रतीक्ष्. **-s.** रक्षा, निरूपणं. 2 रक्षिन् *m.*, रक्षापुरुषः, रक्षितृ *m.* 3 जागरणं, जागरूकत्वं, दक्षता. 4 प्रहरः, यामः; 'w.-house' उद्घाटः; 'w.-man' रक्षिन् *m.*; रक्षकः; प्रहरिन् *m.*, वैबोधिकः, वैतालिकः; 'w.-word' प्रत्ययवाच् *f.* **-ful,** *a.* जागरूक, दक्ष, सावधान, अप्रमत्त. 2 प्रजागर in comp., उन्निद्र.

Water, *s.* जलं, अंबु-अंभस् *n.*, उदकं, वारि; पयस् *n.*, तोयं, सलिलं, नीरं पानीयं, वार् *f.*, अप् *f.* (pl.) पाथस् *n.* 'land and w.' स्थलजले; 'place where w. is distributed' प्रपा, पानीयशालिका; 'by w.' जलेन, जलवर्त्मना; 'of first w.' अनर्घ; 'it can hold w.' प्रमाणकोटिं प्रवहमवति. 2 मूत्रं, प्रस्रावः; 'make w.' मूत्रोत्सर्गं कृ; 'w.-carrier' जलवाहः, उदवाहः, दृतिहारः; 'w.-closet' शौचकूपः; 'w.-course' जलमार्गः, परि(री)वाहः; 'w.-fall' जलप्रपातः, निर्झरः; 'w.-ing place' प्रपा; 'w.-man' नाविकः, उदवाहः; 'w.-melon' कालिंदं, सेतु *n.*, खर्बुजं, कालिंगं; 'w.-mill' जलचालितयंत्रं, जलयंत्रं; 'w.-pot' घटः, कुंभः, कलशः-शः; *See* **Jar;** 'w.-proof' जलाभेद्य; 'w.-snake' जलसर्पः; राजिलः; 'w.-spout' जलयंत्रः; 'w.-wheel' घटीयंत्रं, उदंचनयंत्रं. **-v. t.** (जलेन) सिच् 6 P, सृ c. रुह् 1 P. 2 जलं पा c. or दा 3 U. **-v. i.** जलं स्रु 6 P or स्रु c. or पत् c.; 'my eyes are w. ing' जललवस्यंदिनी नेत्रे. 2 लालायते (D.). **-ed,** *a.* जलप्लुत, अनूप, जलसिक्त; 'w. by rivers' नदीमातृक; 'w. by rain' देवमातृक. **-y,** *a.* जलमय (यी *f.*), जलात्मक, जलरूप; 'w. shafts' वर्षशराः, धाराशरसंपाताः. 2 जलाढ्य, बहूदक, जलप्लुत, अनूप, जलप्राय.

Wattle, *s.* काष्ठावरणं. 2 मशाखा.

Wave, *s.* तरंगः, ऊर्मि *f.*, वीचि-ची *f.* कल्लोलः, भंगः, भंगि-गी *f.* **-v. t.** धू 5, 9 U or c. (धूनयति), वि-आ-°, चल् c., प्रेर् c. 2 उत्सृज् 6 P, परित्यज् 1 P. **-v. i.** इतस्ततः प्र-वि-चल् 1 P, धू pass. **-y,** *a.* तरंगित, ऊर्मिमत्, कल्लोलमय (यी *f.*), भंगिमत्, भंगुर, उन्नतानत.

Waver, *v. i.* दोलायते (D.), द्वैधीभू 1 P, सं-शी 2 A, विकल्प् 1 A; 'his mind w. ed being at a loss which course to follow' इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः (R. xiv. 34); oft. by अनवस्थित, अकृतनिश्चय also. **-ing,** *a.* अनिश्चित, दोलायमान, संदिग्ध, अनवस्थित.

Wax, *s.* लाक्षा (for sealing). 2 सि(सि)क्थं, सिक्थकं, मधूच्छिष्टं, मधुजं. 3 कर्णमलं, तोक्मं. **-v. i.** वृध् 1 A: 'w. ing and waning,' वृद्धिक्षयौ, 'the moon w. ed' कलावृद्धो बभूव; 'w. ing hot' क्रोधिष्ठो भूत्वा. 2 सिक्थकेन लिप् 6 P or अंज् 7 P. **-en, -y,** *a.* सिक्थमय (यी *f.*), सिक्थात्मक.

Way, *s.* मार्गः, पथिन् *m.*, अध्वन् *m.*, वर्त्मन् *n.*, पद्धति-ती *f.*, अयनं, सरणि-णी *f.*, पद्धति-ती *f.*, पदवी; 'step in a wrong w.' अपथे पदमर्पयंति (R. ix. 74). 2 अंतरं, मार्गपर्यंतः; 'a little w.' ईषद्दूरं, स्तोकांतरं. 3 उपायः, युक्ति *f.* 4 प्रकारः, विधिः, रीति *f.*, क्रमः, मार्गः; 'a good way' अतियंताः,

कुपंथाः, सत्पथः, कुपथः; 'a bad or wrong w.' अपंथाः; अपथः, व्यध्वः, दुरध्वः, विमार्गः, विपथः, कद्ध्वन् m.-,का (कु) पथः; 'a place where four w. s meet' शृंगाटकः, चतुष्पथं; 'a dreary w.' प्रांतरं, दूरशून्योऽध्वा 'difficult w.' कांतारः-रं, दुर्गमं वर्त्म, दुर्गसंचरः, संक्रमः. 5 (With numerals) Ex. by धा; 'in two w. s' द्विधा; शतधा &c.; 'a long w. off' सुदूरं, 'on the w.' अंतरा, अंतरे; 'stand or come in the (one's) w.' परिपंथीभू, अंतरायः &c. ('Obstacle', q. v.) भू; (lit.) नयनपथं-विषयं-पा 2 P; 'in this, that-w.' इत्थं-एवं, तथा; 'by w. of example' निदर्शनद्वारा-रूपेण; 'lead the w.' मार्गं आदिश् 6 P or दृश् c.; 'this w.' 'this w.' इत इतः; 'by w. of' द्वारेण, रूपेण; 'make w.' अपसर, अपेहि अंतरं दीयतां; 'in every way' सर्वथा; 'in another w.' अन्यथा; 'w.-farer' पथिकः; *See* **Traveller**; 'w.-lay' पथि निभृतं प्रतीक्ष् 1 A (हननार्थं, वधार्थं), पथि अवस्कंद् 1 P; 'w.-ward' प्रतीप, स्वैरिन्, दुर्ललित; *See* **Obstinate**; 'w.-worn' अध्वश्रांत, अध्वसंजातखेद.

Weak, *a.* दुर्बल, अशक्त, अबल, क्षीणबल, बल-शक्ति-हीन, निःसत्त्व, निस्तेजस्, निर्वीर्य, अल्प-बल-शक्ति. 2 (In mind) मंद, अल्पधी, विकलचित्त; 'w. point or side' छिद्रं, रंध्रं, दोषः, मर्मस्थानं. **-en,** *v. t.* दुर्बलीकृ 8 U, शक्तिं-बलं हृ 1 P, शक्तिं अव-सद् c. or अपचि 5 U; 'to be w.-ed' अपचि pass.; *See* **Waste, Lean.** **-ed,** *a.* हृतबल, क्षीणशक्ति, ह्रस्व (form). **-ness,** *s.* दौर्बल्यं, बल or शक्ति-क्षयः or नाशः, असामर्थ्यं, बल-सत्त्व-हानि *f.* 2 दोषः, (पौरुषदोषाः); छिद्रं.

Weal, *s.* हितं, कल्याणं, क्षेमं, श्रेयस् *n.*, भद्रं, कुशलं; 'w. and woe' शुभाशुभं.

Wealth, *s.* धनं, द्रव्यं, वसुः, *n.* अर्थः, वित्तं, द्रविणं, संपद् *f.*, हिरण्यं, विभवः, स्वमं, संपत्ति *f.*, ऐश्वर्यं, रै *f.*, रि(ऋ)क्थं, द्युम्नं, स्वापतेयं; 'w. in cattle' गोधनं. **-y,** *a.* धनिन्, धनिक, धन-वित्त-वत् &c., सधन, वित्तसंपन्न, सश्रीक, वसुमत्, अर्थयुक्त, विभवशालिन् and sim. comp.

Wean, *v. t.* स्तन्यं त्यज् c. or हा c. (हापयति) or वियुज् c. 2 विरक्ती-विमुखी-कृ 8 U; *See* **Separate.** **-ing,** *s.* स्तन्यत्यागः. 2 विरक्ति *f.*, वैराग्यं, संगत्यागः.

Weapon, *s.* शस्त्रं, अस्त्रं, आयुधं, प्रहरणं, हेति *f.*

Wear, *v. t.* परि-धा 3 U, धृ 1 P, 10, भृ 3 U, वस् 2 A. 2 (Away) क्षि 5 P, नश् c., विलुप् c., प्रमृज् 2 P or c.; घर्षणेन नश् c. 3 जीर्णीकृ 8 U. 4 अव-,सद् c. खिद् c., क्लम् c.; ग्लै c.; *See* **Fatigue.** *-v. i.* (Away) क्षि pass., अवसद् 1 P, अपचि pass. 2 (By use) जॄ 4 P, जर्जरीभू 1 P; 'when the night had almost worn away' क्षीणभूयिष्ठायां क्षपायां; 'w. off' अपगम् 1 P, नश् 4 P, क्षि pass.; 'w. out' जीर्णी-जर्जरी-कृ, अपचि; (*v. i.*) जॄ, ज्या 9 P, जर्जरीभू. *-s.* परि-,धानं, अपचयः, उपयोगः. 2 घर्षणं. 3 सेतुः, आलि *f.* **-er,** *s.* धारिन्, भृत in comp. **-ing,** *a.* धारिन्, भृत, धर in comp. 2 परिधानयोग्य.

Weary, *v. t.* आयस् c., क्लम् c., खिद् c.*-v. i.* आयस् 1, 4 P, क्लम् 1, 4 P. **-ied,** *a.* खिन्न, क्लांत, परिश्रांत, म्लान, आत्तखेद; 'w. of' निर्विण्ण, निर्वेदमापन्न; *See* **Disgusted;** 'w. of life' जीवितादुद्विजमानः (Mal 3). **-iness,** *s.* क्लमः, श्रमः, खेदः, आयासः; *See* **Fatigue,-ed** &c. **-isome,** *a.* श्रम-खेद-जनन (नी *f.*), आयासकर (री *f.*), श्रमावह, कष्टमय.

Weasel, *s.* नकुलः, बभ्रुः, अंगूषः.

Weather, *s.* कालः, दिनं; 'bad w.' दुर्दिनं; 'good w.' सुदिनं; 'if the w. be fine' यदि दुर्दिनं न स्यात्; 'w.-beaten' वाताहत, प्रभंजनोपहत; 'weather-glass,' *s.* वायुमापकयंत्रं. 'w.-wise' वातादिलक्षणविद्, कालविद्. *-v. t.* तॄ 1 P, प्रत्यव-स्था 1 A; पारं गम् 1 P.

Weave, *v. t.* वे 1 P; वप् 1 P, गुं(गु)फ् 6 P, वि-,रच् 10. **-er,** *s.* तंतुवायः-पः, कुविंदः, पटकारः. **-ing,** *s.* वायः-पः, तंतुतंत्र-वायः, ऊति-व्यूति *-f.*, पटनिर्माणं, पटकर्मन् *n.*

Web, *s.* जालं, तंत्र-तंतु-संतति *f.*; (of the eye) पटलं; 'w.-footed' जालपाद.

Wed, *v. t.* वि-उद्-वह् 1 P, परि-णी 1 P. **-ded,** *a.* ऊढ, परिणीत. 2 आसक्त, अचलचित्त, रक्तिन्, (to an opinion); 'w.-lock' विवाहः; 'a wife married in w.-lock' धर्मपत्नी, सहधर्मचारिणी; *See* **Marriage.**

Wedge, *s.* कीलः, शंकुः *-v. t.* संपीड् 10, संबाध् 1 A, संवृह् 9 P.

Wednesday, *s.* बुधवासरः.

Weed, *s.* कक्षः, तृणादिकं, स्तंबः; (fig.) अतिरेकः, भ्रमं, प्रसरस्तंभनं. 2 (W. s) वासस् *n.*; *See* **Garment;** 'widow's w. s' विधवावसनं, चीरं. *-v. t.* (Out) (कक्षं) उद्-हृ 1 P, निर्दो 4 P, उत्पट् 10. **-er,** *s.* निर्दातृ *m.*, कक्षोद्धारिन् *m.* **-y,** *a.* कक्षपूर्ण-बहुल.

Week, *s.* सप्ताहः, सप्तदिनं; 'w.-day' वारः. **-ly,** *a.* साप्ताहिक (की *f.*), सप्तदैनिक (की *f.*). *-adv.* प्रतिसप्ताहं.

Ween, *v. i.* मन् 4 A; *See* **Think;** 'over w.-ing' अत्यंताभिमानिन्.

Weep, *v. i.* रुद् 2 P, वि-लप् 1 P, अश्रूणि मुच् c. or विमुच् 6 P, आ-,क्रंद् 1 P; *See* **Cry, Lament. -ing,** *s.* रुदितं, रोदनं, विलापः, आक्रंदनं, क्रंदितं, अश्रुपातः. -*a.* साश्रु, अश्रुलोचन.

Weigh, *v. t.* तुल्-तुल् 10, तुलायां धृ 10. 2 (In mind) वि-मृश् 6 P, आलोच् 10, विचार् c., वि-गण् 10; *See* **Think. 3** (Anchor) उत्तुल्; 'w. down' अभि-भू 1 P, आकुलीकृ; 'w. duly' परिच्छिद् 7 P, सूक्ष्मं निरूप् 10. -*v. i.* Ex. by 'Weight' q. v.; 'what does it w.' किंभारमिदं; किं भारपरिमाणं; 'w. upon' पीड् 10, बाध् 1 A; *See* **Afflict;** 'w. with' मन् pass.; 'dress w. s much with them' वेषस्तैर्बहु मन्यते. -**ing,** *s.* तोलनं, विगणनानं. -**Weight,** *s.* मानं, भारः, तोलः, परिमाणं, भारपरिमाणं, गुरुत्वं, ∠ गुरुत्वं, गौरवं, प्रभावः, भारः. **3** भारः, धुर् *f.*; 'of little w.' लघ्वर्थ, लघुप्रभाव, अगुरु. -**y,** *a.* गुरु, महत्, समभाव, सप्रमाण.

Weir, *s.* बंधः, योगः.

Weird, *s.* विधिः, अभिचार-,मन्त्रः. -*a.* अतिमानुष.

Welcome, *a.* स्वागत. **2** शुभ, इष्ट, हित; प्रिय, अभिमत, सुखद. -*v. t.* स्वागतं व्याहृ 1 P, सभाज् 10, अभिनंद् 1 P, सत्कृ 8 U, पूज् 10; (आश्रमसुरैरभिनंदितागमनेषु समीपेषु Ks. 49). -*interj.* स्वागतं (with dat). -*s.* स्वागतं, सभाजनं, अभिनंदनं.

Weld, *v. t. See* **Unite.**

Welfare, *s.* हितं, कल्याणं, क्षेमं, कुशलं, श्रेयस् *n.*, भद्रं, मंगलं, सुखं, भूति *f.*, शिवं, सुस्थिति *f.*

Welkin, *s.* नभस् *n.*; *See* **Sky.**

Well, *s.* वापी, कूपः, प्रहिः, अंधुः, दीर्घिका (large w.), उदपानं; 'covering of a w.' वि(वी)नाहः; 'reservoir near a w.' आहावः, निपानं, उपकूपजलाशयः. **2** स्रुति *f.* -*a.* कुशलिन्, स्वस्थ, सुस्थशरीर, निरामय, नीरोग, कल्य; *See* **Healthy. 2** कुशल,क्षेम, सुखिन्; oft. by कुशलं; अपि कुशलमस्याः प्रजापालस्य मातुः (U. 4) 'is she w.'; 'got w. again' पुनः प्रकृतिस्थोऽभवत्, प्रकृतिमापन्नः; 'know that we are doing w. in every respect' सर्वत्र नो वार्तमवेहि (R. v. 13). -*adv.* सु pr., (सुकृत, सुदर्शन &c.); सुष्ठु, साधु, सम्यक्, 'w. said' साधूक्त, सूक्त; 'w. off' सुस्थित *a.*, वित्तवत्, सुस्थ; 'you might as w. have kept all (fruits)' सर्वथा रक्षणेऽपि न तव कश्चिद्दोषोऽभविष्यत्. -*interj.* बाढं, तथा; 'saying very w.' पुच्छते, बाढं, तथेति उक्त्वा; 'very w.' भवतु; 'w. then' तेन हि. **2** (As expletive) भवतु, अस्तु, *gen.* by तावत्; 'w. we go away now' साधयामस्तावद्वयं; 'w.-behaved' साधुशील, सुवृत्त; 'w.-being' हितं, कुशलं; *See* **Welfare;** 'w.-born' कुलीन, सत्कुलजात; 'Well-bred' *a.* सुविनीत; 'w.-done' साधु साधु; 'w.-informed' बहुज्ञ, बहुश्रुत; 'w.-meaning' सदाशय, हितबुद्धि; 'w. nigh;' *See* **Nearly;** 'w.-read' अधीतिन्, सर्वशास्त्रपारंगत, बहुश्रुत; 'Well-timed' *a.* उचितावसर. 'Well-to-do' *a.* ससुख, ऐश्वर्यशालिन्; 'w.-wisher' हितकामः, हितैषिन् *m.*, प्रियैषिन् *m.*

Welter, *v. i.* लुठ् 6 P, लुठ् 4 P; *See* **Roll.**

Wen, *s.* मांसार्बुद.

Wench, *s.* बंधकी, पुंश्चली, कुलटा. ∠ कन्या, तरुणी. -*v. i.* **Fornicate,** q. v.

Wend, *v. t.* (one's way) गम् 1 P, चल् 1 P; *See* **Go;** 'here he w. s his way' इत एवाभिवर्तते.

West, *s.* प्रतीची, पश्चिमा, वारुणी. -*a.*, -**erly,** -**ern,** *a.* पाश्चात्य, प्रतीच्य, चरम, अपर. **2** पश्चिमाभिमुख (खी *f.*). -**wards,** *adv.* प्रतीचीमभि, प्रतीच्यभिमुखं, पश्चिमदिशि.

Wet, *a.* आर्द्र, क्लिन्न, सिक्त, उक्षित, उन्न, जलार्द्र. -*v. t.* क्लिद् c., आर्द्रीकृ 8 U, आर्द्रयति (D.); *See* **Melt.** -*s.* आर्द्रता, तेमः, क्लेदः. **2** दुर्दिनं; 'w.-nurse' स्तन्यदायिनी, धात्री, उपमातृ *f.*

Wether, *s.* छिन्नवृषणो मेषः.

Whack, *v. t. See* **Strike.**

Whale, *s.* तिमिः, तिमिंगिलः.

Wharf, *s.* घट्टः, तरस्थानं. -**age,** *s.* तरपण्यमूल्यं, घट्टदेयं शुल्कं.

What, *pron.* किं (कः-का-किं), रिक in comp.; 'w. then' ततः किं, किं तर्हि; 'w. is he doing now' स (राजा) किमारंभः संप्रति (U. 2); 'w. is his name' किंनामासौ; 'w. else' अथ किं; 'w. is that to me' किं मम तेन; 'w. though' यद्यपि. **2** यद्यद्. -*interj.* कथं, आः, किं, ननु. -**ever,** -**soever,** *a.* यद्यद्. **2** यत्किम्, यत्किंचित्; 'to w. person' यस्मै कस्मैचित्पुरुषाय; यो वा को वा भवान्यस्यं, &c.

Wheat, *s.* गोधूमः, सुमनः -**en,** *a.* गोधूममय, (*s.*) in comp.

Wheedle, *v. t.* चाटूक्तिभिः प्र-लुभ् c. or वंच् 10 or लल् 10; *See* **Flatter.**

Wheel, *s.* चक्रं, रथांगं, मंडलं. -*v. i.* परिभ्रम् 1, 4 P, परा-परि-आ-वृत् 1 A, मंडलाकारेण भ्रम्. -*v. t.* व्यावृत् c., भ्रम् c. -**ed,** *a.* चक्रिन्, चक्रयुक्त. -**Wheel-wright,** *s.* रथकारः, चक्रकारः.

Wheeze, *v. i.* कृच्छ्रेण श्वस् 2 P.

Whelp, *s.* शाव:-वक:, शिशु:, किशोर:.

When, *adv.* यदा; by loc. abs.; ' w. the speech was over ' वचस्यवसिते तस्मिन्. 2 कदा; ' w.-ever,-soever ' यदा यदा, यदा कदाचित्. **-Whence,** *adv.* यत:, यस्मात् 2 कुत:, कस्मात्.

Where, *adv.* क्व, कुत्र. 2 यत्र; ' w.-ever ' यत्र यत्र; यत्र कुत्रापि, यत्र कुत्रचित्, ' w.-as ' यत:, विपर्यये तु; ' w.-by ' येन; ' w.-fore ' यदर्थं, यत:, येन, किमर्थं, कस्य हेतो:; ' w.-in ', ' w.-to ' यत्र; ' w.-upon ' यदनंतरं, तदनु.

Whet, *v. t.* तिज् c., नि-,शो 4 P, क्ष्णु 2 P. **-s., -stone,** *s.* शाण:-णी, शाणाश्मन् *m.*

Whether, *pron.* कतर:-रा रत्. **-conj.** किं followed by वा, उत, आहो or आहोस्वित् (for ' or '), ' w. he do that or not ' स तत्करोतु न करोतु वा.

Whey, *s.* मस्तु *n.*, दधिमंड.

Which, *pron.* (Relative) यत् *m. f. n.* (य:-या-यत्). 2(Interrogative)किं *m. f. n.* (क:-का-किं); 'w. of two' यतर, कतर; ' w. of many ' यतम, कतम; 'w.-ever ' ex. by repeating (1).

Whiff, *s.* फूत्कार:, फूत्कृतं.

While, *s.* क्षण:, मुहूर्त:, काल:, समय:; ' for a w. ' कंचित्कालं, क्षणं; ' after a long w. ' चिरेण; ' not worth w. ' निष्फल, निरर्थक, न उपयुक्त; ' worth w. ' उपयुक्त. **-conj. Whilst,** यदा, यावत् (followed by तावत्); gen. by pres. part.; ग्रामं गच्छंस्तृणं स्पृशति ' w. going ' &c. **-v. t.** (away) क्षिप् 6 P, गम् c., हृ 1 P, विलुप्.

Whim, *s.* कामचार:, कामवृत्ति *f.*, छंद:, छंदस् *n.*, चापल्यं, मनोलौल्यं, लहरी, चित्ततरंग:; ' at one's w. ' स्वच्छंदेन, स्वेच्छया; ' acting according to another's w. ' छंदोनुवृत्ति *f.* **-Whimsical,** *a.* कामचारिन्, स्वैरिन्, स्वैर, स्वच्छंदानुवर्तिन्, स्वच्छंद; चपल, लोल, अनवस्थित.

Whimper, *v. i.* बालकवत् वद् 2 P or क्रंद् 1 P.

Whine, *v. i. See* **Murmur.**

Whinny, *v. i. See* **Neigh.**

Whip, *s.* कशा-षा, प्रतोद:, प्रतिष्कष:-श:. **-v. t.** कशया प्र-हृ 1 P or तड् 10 or चुद् 10 or दंड् 10 or आहन् 2 U. **-ping,** *s.* कशाघात:-ताडनं-प्रहार:; ' deserving w. ' कश्य, कशार्ह.

Whirl, *v. i.* घूर्ण् 6 P, 1 A, परि-,भ्रम् 1, 4 P. **-v. t.** घूर्ण् c., भ्रम् c. (भ्रमयति). **-s., -ing,** *s* भ्रमणं, घूर्णनं, भ्रमि *f.*; आवृत्ति *f.*; ' w -pool ' आवर्त:, भ्रमि:, भ्रम:, जलावर्त:, जलगुल्म:, ' w.-wind ' चक्रवात:, वातावर्त:; वात्या, वातभ्रम:.

Whisk, *v. t.* अतिशीघ्रं चल् c. or विक्षिप् 6 P. **-s.** लघुक्षेप:. 2 चामरं (for flies).

Whiskers, *s.* गंडलोमन् *n.*, श्मश्रु:.

Whisper, *v.* नीचै:-उपांशु-वद् 1 P; कर्णे जप् 1 P or कथ् 10 or कथ 2 P; कर्णे उपजप्; ' w. aside ' जनांतिकं वद्. **-s., -ing,** *s.* कर्णवाद:, उपांशुवाद:, कर्णेजप:; उप:-कर्ण; ' in a w. ' उपांशु, जनांतिकं, नीचैस्त्वरेण. **-er,** *s.* कर्णे (र्ण)जप:-कथक:.

Whistle, *s.* शीशूशब्द:. 2 वंश:-शी. **-v. i.** शीशूशब्दं कृ 8 U.

Whit, *s.* लेश:, लव:, गंध:, अणु:; ' not a w. ' न मनागपि, न स्तोकमपि, नाल्पमपि.

White, *a.* शुक्ल, श्वेत, धवल, शुभ्र, सित, गौर (री *f.*), शुचि, अवदात, वि[illegible], [illegible], पांडुर, अमिमल. **-s.** श्वेतवर्ण:, शुक्लवर्ण:, शुक्ल:; श्वेत:, सित:, &c.; ' dressed in w. ' श्वेतवासो दधान. **-en,** *v. t.* धवलीकृ 8 U, धवलयति (D.) &c. **-v. i.** धवलीभू 1 P, धवलायते (D.). **-ish,** *a.* आपांडु. **-ness,** *s.* शुक्लता, धावल्यं, शुभ्रता, धवलिमन्, शुक्लिमन् *m.* **-White-wash,** *v t* सुधया लिप् 6 P or धवलीकृ; ' a house w. ed ' सुधाभवनं. **-s.** सुधा, सुधालेप:. **-Whites,** *s.* श्वेतप्रदर:.

Whither, *adv.* कुत्र, क्व. 2 यत्र.

Whitlow, *s.* नखंपच:, चिप्पं, नखव्रणं.

Whittle, *v. t.* छिद् 7 U, तक्ष् 1 P.

Who,-ever, &c. *See* **Which** &c. *m. f.*

Whole, *a.* सकल, समग्र, कृत्स्न, अखिल, समस्त, सर्व, अखंड, निखिल, विश्व, अशेष, नि:शेष, पूर्ण, अनून. 2 (Number) अभिन्न. **-s.** साकल्यं, कार्त्स्न्यं, सामग्र्यं, समास:, ' on the w. ' एवं च, एतावता, समासत:, समासेन, ' the w. of ' ex. by (*a.*) **-ly,** *adv.* समग्रं, साकल्येन, अशेषेण, निरवशेष, सर्वथा, सर्वत:-श:. सर्वभावेन, एकांतत:. **-Wholesale,** *a.* Ex. by, स्तूप in comp., समस्त (विक्रय:), ' w. dealer ' स्तूपविक्रयिन्, ' w. buying ' समस्तराशिक्रय:.

Wholesome, *a.* पथ्य, आरोग्यावह, हितावह, *See* **Salutary.**

Whoop, *s.* सिंहनाद:, क्ष्वेडा.

Whore, *s. See* **Prostitute;** ' w.'s son ' वेश्यापुत्र:; ' w.-monger ' भुजंग:, विट:. **-dom,** *s.* वेश्यावृत्ति *f.* प्रसक्ति *f.*

Why, *adv.* किं,कुत:, कस्मात्, किमर्थं, किंनिमित्तं, केन हेतुना; ' w. do you do so ' एवं करोषि कस्तव हेतु:. 2 ननु; ' w. you yourself are before me ' ननु भवानेव ममाग्रे वर्तते (S. 2).

Wick, *s.* दशा, वर्ति *f.*, वर्तिका, स्नेहिनी.

Wicked, *a.* (Of persons) दुष्ट, दुर्जन, दुरात्मन्, पाप, शठ, दुराचार, खल, पापकर्मन्, दुर्वृत्त, नृशंस, पापात्मन्, पापचरित, अधार्मिक (की *f.*), दुश्चरित्र. 2 (Of things)

दुष्ट, पाप in comp., दुर् pr.; 'w. policy' दुर्णीतिः; *See* **Sinful.** **-ly,** *adv.* दुष्टतया, दुर्वृत्ततया, खलवत्. **-ness,** *s.* दुष्टता, दौर्जन्यं, दौरात्म्यं, पापं, दुष्कृतं-ति *f.*, पापकर्मन् *n.*, दुराचारः, अनाचारः.

Wicker, *a.* वैणव (वी *f.*), वैदल (ली *f.*); 'w.-work' वैदलं.

Wide, *a.* विस्तीर्ण, विशाल, उरु, विपुल, पृथु; *See* **Broad;** 'w. of the mark' लक्ष्यभ्रष्टच्युत, असाम्प्रतिक (की *f.*). **-adv., -ly,** *adv.* विपुलं, सर्वत्र, सु-अति-बहु pr., 'w. known' सुविख्यात; 'w. awake' सुप्रबुद्ध; 'with eyes w. open' उत्फुल्लनयन. **-en,** *v. t.* पृथूकृ 8 U, विशालीकृ, प्रथ् 10. **-Width,** *s.* विस्तारः, व्यासः, परिणाहः, विशालता.

Widow, *s.* विधवा, अ-गत-भर्तृका, विश्वस्ता, अनाथा, रंडा; 'child-w.' बालविधवा. **-ed,** *a.* अनाथा, मृतभर्तृका. **-er,** *s.* मृतपत्नीकः, गतभार्यः. **-hood,** *s.* वैधव्यं, वैधव्यदशा.

Wield, *v. t.* (हस्तेन) भृ 3 U, धृ 1 P, 10, प्र-उप-युज् 7 A, 10 **2** (A state &c.), प्र-, शास् 2 P, निर्वह् c.; राज्यधुरां वह् 1 P. **-y,** *a.* सुप्रयोज्य; (body) उत्थानयोग्य (S. 2).

Wife, *s.* भार्या, पत्नी, जाया, वधूः, कलत्रं, दाराः *m.* (pl.), स्त्री, परिग्रहः, गृहिणी, गेहिनी, सहधर्मिणी, दयिता, वल्लभा, प्रिया, कान्ता, रमणी, क्षेत्रं, गृहाः (pl.); 'a rival w.' सपत्नी; 'taking a w.' दारपरिग्रहः-क्रिया; 'a w. whose husband has gone abroad' प्रोषितभर्तृका.

Wig, *s.* उपकेशः, कृत्रिमकेशः. **-v.** *t.* निर्भर्त्स् 10 A, उपालभ् 1 A,

Wight, *s.* मानवकः, जंतुः, प्राणिन् *m.*

Wild, *a.* वन्य, वनजात, आरण्यक, वन-अरण्य in comp.; 'a w. mountain' कांतारमध्यवर्ती-वनांतर्गतः-पर्वतः; वनपशुः, वनगजः, वनपुष्पं &c. **2** हिंस्र, क्रूर, क्रव्याद्. **3** उन्मत्त, अतिव्याकुल; 'w. with anger' क्रोधोन्मत्त; 'w. with joy' हर्षोन्मत्त, हर्षनिर्भर. **4** प्रचंड, तीव्र; दुर्दांत, अनियंत्रण, उद्दामवृत्ति, उच्छृंखल; 'w. storm' प्रचंडप्रभंजनः. **5** अयुक्तिक, अनुपपन्न, निरर्थक; *See* **Absurd.** **-erness,** *s.* वनं, अरण्यं; *See* **Forest. 2** मरुः,-भूमि *f.*, धन्वन् *m.* **-ly,** *adv.* उन्मत्तवत्, प्रचंडं, सोन्मादं, उच्छृंखलं. **-ness,** *s.* वन्यता, रौद्रता, उन्मादः, &c.

Wile, *s.* छलं, कपटं, वंचनं, माया, छद्मन् *n.* **-Wily.** *a.* भूरिमाय, मायाविन्, सव्याज, छद्मपर, कापटिक-छाद्मिक-(की *f.*), सकपट.

Will, *v.* संकल्प् c., निर्दिश् 6 P, चिञ् 5 U, निर्णी 1 P. **2 Wish,** q. v. **3** (As auxiliary) by Future or Pot. mood. **-s.** संकल्पः, संकल्प-इच्छा-शक्ति *f.* **2** कामः, इच्छा, अभिलाषः, आकांक्षा, ईहा; 'God's w. be done' ईश्वरेच्छा बलीयसी, प्रभवति भगवान् विधिः; 'against one's w.' बलात्, हठात्, अकामतः; 'would have her w.' आत्माभिप्राये निर्बंधपरासीत्; 'at w.' स्वेच्छया, यथाकामं, स्वैरं, काम in comp.; 'subject to the w. of another' परतंत्र-वश. **3** इच्छापत्रं. **-ful,** *a.* कामतः कृत. **2** स्वैरिन्, काम-स्वेच्छा-चारिन्, स्वैरवृत्तगामिन्, *See* **Wanton. -fully,** *adv.* कामतः, इच्छापूर्वकं, स्वैरं, बुद्ध्या, जानत् *a.* अपि. **-fulness,** *s.* कामचारः, स्वेच्छाचारः, यदृच्छा, स्वैरिता, स्वाच्छंद्यं. **-ing,** *a.* इच्छु, सकाम, उद्यत; oft. by desid. **2** इष्ट, अनुमत, यथेप्सित. **-ingly,** *adv.* सकामं, स्वेच्छया, कामतः, स्वेच्छापूर्वं. **-Would.** (that) Ex. by अपि नाम; अपि नामाहमप्यात्मनोनुरूपं वरं लभेयेति (S. 1); 'w. I had loved him more' वरं तस्मिन्नहमधिकतरं स्निग्धोऽभूवं; यद्धि...अभविष्यं तर्हि-अहो शोभनमापत्स्यत्.

Wilt, *v.i.* म्लै 1 P, ग्लै 1 P.

Win, *v. t.* वि-जि 1 A, विजयिन् *a.* भू; 'won the battle' युद्धे जयमाप, समरविजयी बभूव; 'who is said to w.' यो विजयीति गण्यते-मन्यते. **2** लभ् 1 A, प्राप् 5 P; *See* **Get. 3** आकृष् 1 P, प्र-वि-लुभ् c., *See* **Attract;** 'w. over' स्वपक्षं ग्रह् c., अनुयायिन् *a.* कृ. **-ner,** *s.* जयिन् *m.*, जेतृ *m.* **-ning,** *s.* जयः. **2** लाभः, अर्जितं. **-a. -some,** हृदयहारिन्, चित्ताकर्षिन्.

Wince, *v. i.* वि-,कंप् 1 A, स्फुर् 6 P, 'he did not w.' स भयचकितो नाभवत्; *See* **Start.**

Wind, *s.* वातः, वायुः, पवनः, पवमानः, अनिलः, समीरणः, मारुतः, मरुत् *m.*, मातरिश्वन्, श्वसनः, स्पर्शनः, गंधव(वा) हः, आशुगः. **2** (In stomach) वातः; वायुः. **3** श्वासः; 'w.-fall' वायुपातः; (fig.) अलभ्यलाभः; 'w.-lass' उत्तोलनी; 'w.-mill' वायुचाल्यं चक्रं, वायुपेषणी. **-v.** *i.* वक्रं-कुटिलं-गम् or सृप् 1 P, जिह्मं या 2 P; 'the river runs w. ing for a koss' क्रोशं कुटिला नदी (S. K.) **2 Turn,** q. v. **-v.** *t.* परि-आ-वृत् c. **2** पूर् 10 (मारुतेन), ध्मा 1 P. **2** (Up) संपुटीकृ 8 U, पिंडीकृ, उप-,सं-ह् 1 P; अवसो 4 P; (hair) सं-ह्, सं-यम् c., (संयमय केशपाशं Ka. 84). **-ing,** *a.* वक्र, कुटिल, जिह्म. **-s.** वक्रं, वंकः, पुटभेदः. **-ward,** *adv.* वाताभिमुखं. **-y,** *a.* वातमय (यी *f.*), वातुल. **-Window,** *s.* वातायनं, जालं, गवाक्षः.

Windpipe, *s.* श्वासनलिका.

Wine, *s.* मद्यं, द्राक्षारसः-आसवः, मधु *n.*, माध्वीकं, मदिरा, सुरा; 'w.-bibber'

मद्यपः, सुरापः; 'w.-seller' मद्यविक्रयिन्, शौण्डिकः

Wing, *s.* पक्षः, पत्रं, पतत्रं, गरुत् *m.*, छदः, पक्ष्मन् *n.*, 'root of a w.' पक्षतिः *f.*, पक्षमूलं; 'to be on the w.' डी 1 A; 'under the w. of' आश्रित-*a.* **2** (Of army &c.) पक्षः, वूले, पार्श्वमूलं. -*v. t.*, 'w. the way' अध्वक्रमणं कृ 8 U. -**ed,** *a.* पक्षिन्, पतत्रिन्.

Wink, *v. i.* नि-मिष् 6 P, नि-मील् 1 P, पक्ष्म संकुच् 1 P. **2** संकेतं-संज्ञां-कृ 8 U (नेत्रेण); 'w. at' उपेक्ष् 1 A, न गण् 10. -*s.* निमि-(मे)षः, निमीलनं, पक्ष्मसंकोचः. **2** नेत्रसंज्ञा, अक्षिसंकेतः.

Winnow. *v. t.* वि-, शुध् c., पू 9 U. **2** प्रस्फुट् c.; (fig.) परीक्ष् 1 A; *See* **Discriminate.** -**er,** *s.* पावकः. -**ing,** *s.* पवनं, प्रस्फोटनं; 'w.-ing basket' शूर्पः-र्पं, प्रस्फोटनं.

Winter, *s.* हेमंतः, शिशिरः, तुषारकालः, हिमागमः, हिम-शीत-कालः. -**Wintry,** *a.* (*s.*) in comp.; हैमंत (ती *f.*), हैम (मी *f.*). **2** शीत, शिशिर.

Wipe, *v. t.* प्र-परि-मृज् 2 P or c., प्रं-क्षल् 10, निर्मृज् 1 P, सं-मृज् 9 P; *See* **Wash;** 'w. away.' 'w. out' प्रमृज्, (स्वभावलोलेत्ययशः प्रमृष्टं (R. vi. 41), अप-अवमृज्. -*s.* मार्जनं, प्रक्षालनं. **2** प्रहारः. -**er,** *s.* मार्जनी, प्रक्षालनी.

Wire, *s.* तंत्रं, तंत्री, तारः-रा, धातुसूत्रं, लोहतारा-सूत्रं-तंतुः. -*v. t.* तारयंत्रेण प्रेष् c. -**y,** *a.* तंत्रमय (यी *f.*).

Wise, *a.* प्र(प्रा)ज्ञ, विज्ञ, विदग्ध, ज्ञानवत्, पंडित, प्रज्ञावत्, धीमत्, विवेकिन्, सुधी, धीर, मति-बुद्धि-मत्, मनीषिन्, विद्वस्; *See* **Learned** also. **2** (Of acts) सु in comp.; ज्ञानयुक्त, वैदग्ध्यमूलक; 'w. saying' सुभाषितं; 'w. step' साधुमार्गः. -*s.* प्रकारः; *See* **Manner;** 'in this w.' एवं, इत्थं. -**ly,** *adv.* प्रज्ञया, ज्ञानेन, सविवेकं, सम्यक्, सुसमीक्ष्य, सुष्ठु, प्राज्ञवत्. -**Wisdom,** *s.* प्रज्ञा, ज्ञानं, वैदग्ध्यं, बुद्धि *f.*, धीः, विवेकः, वैदुष्यं, पांडित्यं, धीरता, मनीषा. -**Wiseacre,** *s.* पंडितंमन्यः.

Wish, *v. t.* इष् 6 P, स्पृह् 10 (with dat.), सं-, ईह् 1A, वांछ् 1 P, आ-, कांक्ष् 1 P, अभिलष् 1, 4 P, कम् 1 A, वश् 2 P; oft. by desid. forms; जिगमिषति 'w.-es to go;' जिघृक्षति &c.; w. ill to' असूयति (D.) (with dat.); अमंगलं आशंस् 1 A; 'I w. no evil to any' न मे कस्मिन्नपि द्रोहबुद्धिः-द्वेषभावः; 'I w. I could see him again' अपि नाम तं पुनरपि पश्येयं; 'he had nothing left to w. for' न किमपि तस्य स्पृहणीयमासीत्. -*s.* इच्छा, मनोरथः, स्पृहा, ईहा, कामः, कृतं, वांछितं, अभिलाषः; वांछा, कांक्षा.

Wisp, *s.* शुष्कतृणकूर्चकः.

Wistful, *a.* *See* **Eager.**

Wit, *s.* बुद्धि-मति-*f.*, मेधा, धीः; *See* **Intellect.** **2** बुद्धिचातुर्यं, बुद्धिविलासः-चातुर्यं; 'was at his w.'s end' किंकर्तव्यतामूढः-कुंठितमतिः-आसीत्, विकलीकृतः. **3** (Person) वाक्चतुरः, नर्मज्ञः, परिहासकथः, नर्मभाषिन् *m.* **4** रसः, नर्मन् *n.*, वैदग्ध्यं, सारस्यं, नर्मरसिक-उक्ति *f.*, नर्मालापः-भाषणं; 'to w.' तद्यथा. -**ty,** *a.* नर्मवेदिन्, नर्मभाषिन्; सरस विदग्ध, रसयुक्त, परिहासजनन (नी *f.*); 'w. speech' परिहासालापः, नर्मवाक्यं, नर्मालापः.

Witch, *s.* डाकिनी, मायाविनी, कुहकिनी, मायिनी. -**ery,** 'w.-craft', *s.* माया, अभिचारः.

With, *prep.* Gen. ex. by instr. **2** (Manner) by instr.; प्रीत्या 'w. affection'; by comp. with स, सहर्षं, सभयं &c.; पूर्वं, पूर्वकं in comp.; 'w. respect' मानपुरःसरं, आदरपूर्वकं. **3** (Accompaniment) by Bah. comp.; 'Madana w. Rati' रतिसहायो मदनः; सकृष्णो रामः; gen. by समं, साकं, सार्धं, सह, सहितं, with instr.; 'send the book w. Rāma रामहस्ते पुस्तकं प्रेषय. **4** (With verbs) सं; 'to live w.' सं-वस्. **5** (On the side of) पक्षे. **6** (In the opinion of) मतेन, मते, (तव मतेनाकिंचित्करमिदं) 'w. all' अनादृत्य; *See* 'in spite of': under **Spite.** -**al,** *adv.* समं, तथा च, अपि च, तथैव.

Withdraw, *v. t.* प्रति-सं-हृ 1 P, अपाकृष् 1 P, अप-नी 1 P, प्रत्यप-हृ; 'w.-s the world into himself' आत्मन्येवाखिलं विश्वं संहरति -*v. i.* अप-क्रम् 1 U, 4 P, अप-सृ 1 P, अप-गम् 1 P, परावृत् 1 A; *See* **Retire.** -**al,** *s.* संहारः, संहरणं, अपनयन, अपक्रमः-मणं.

Wither, -*v. i.* म्लै 1 P, ग्लै 1 P, वि-शॄ pass, सद् 1 P, क्षि pass. -*v. t.* नश् c., शॄ c.; *See* **Fade.** -**ed,** *a.* म्लान, ग्लान, विशीर्ण, शुष्क, जीर्ण.

Withers, *s.* स्कंधदेशः, स्कंधः.

Withhold, *v. t.* नि-ग्रह् 9 P, अव-नि-रुध् 7 U, नियम् 1 P, प्रति संहृ 1 P, अपसं-हृ, नि-वृ 10; न दा 3 U.

Within, *adv.* अंतर् in comp.; अंतर्वर्तिन्. **2** चित्तोद्भूत, आंतर (*a.*). -*prep.* अंतरे, अभ्यंतरे, मध्ये, अंतर् in comp.; 'w. the house' गृहाभ्यंतरे, अंतर्गृहं &c.; 'w. six months' षण्मासाभ्यंतरे, षण्माससमये; अर्वाक् (with abl.) **2** (In the reach of) गोचर, विषय, ग्राह्य, in comp.; 'w. hearing' कर्णगोचरीभूत; 'w. the reach of eyes' नयनगोचरे, नयनविषये &c.; 'w. the reach of the hand' हस्तप्राप्य-ग्राह्य.

Without, *prep.* विना (with acc., instr., abl.), अंतरेण (with acc.), ऋते (with abl.) वर्जयित्वा, मुक्त्वा, विहाय (with acc.); by अ-निर्-pr., हीन, रहित, वर्जित, व्यतिरेकेण, व्यतिरिक्त in comp.; 'w. delay' अविलंबं; 'w. doubt' निःसंशयं, असंशयं; 'w. money' धनहीन-रहित, निर्धन. 2 (Before participles) By अ (अन्); 'w. burning' अदहन्, अदग्ध्वा; 'w. being marked' अलक्षित. 3 बहिः (with abl.), बहिर्भागे. *-adv.* बहिः, बाह्यतः; 'lying w.' बहिःस्थित.

Withstand, *v. t.* निरा-प्रति-कृ 8 U, प्रतिकूलयति (D.), वि-रुध् 7 U, परिपंथीभू 1 P, (वज्रपरिकरस्य ते न त्रैलोक्यमपि क्षमं परिपंथीभवितुं Ve. 3); प्रत्यव-स्था 1 A; *See* **Oppose.**

Witness, *s.* साक्षिन् *m.*; 'w. -es for prosecution' पूर्ववादिनः साक्षिणः; 'ear-w.' श्रुतसाक्षी; 'eye-w.' दृष्टसाक्षी. 2 साक्षात् द्रष्टृ *m.* 3 साक्ष्यं, प्रमाणं. *-v. t.* प्रत्यक्षीकृ 8 U, प्रत्यक्षं दृश् 1 P; *See* **See.** 2 साक्ष्येण प्रमाणीकृ. *-v. i.* साक्ष्यं दा 3 U, साक्षीभू 1 P.

Wizard, *s.* मायाकारः; *See* **Magician.**

Wizen, *a.* म्लान, ग्लान.

Woe, *s.* दुःखं, शोकः; *See* **Sorrow, Grief.** *-interj.* हा, धिक्, (with acc.); अहो बत, हा कष्टं. **-ful,** *a.* **Sorrowful,** q. v.; 'is in a w. plight' कष्टमवस्थापन्नः (U. 3).

Wold, *s.* वनं, अरण्यं. 2 गिरिः.

Wolf, *s.* वृकः, कोकः, ईहामृगः.

Woman, *s.* स्त्री, नारी, अंगना, अबला, योषित्, वनिता, ललना, योषा, सीमंतिनी, वधूः, वामा, महिला; 'nobly-born w.' कुलांगना, कुलजा, 'young w.' युवतिः-ती, यूनी, तरुणी, प्रमदा, बाला; 'beautiful w.' सुंदरी, प्रमदा, सुभगा, नितंबिनी, वामलोचना; 'an excellent w.' वरारोहा, मत्तकाशिनी, उत्तमा, वरवर्णिनी; 'passionate w.' कोपना, भामिनी; old w.' स्थविरा, वृद्धा, जरती 'virtuous w.' सती, साध्वी, पतिव्रता, सुचरित्रा, कुलस्त्री, कुलपालिका. **-hood,** *s.* यौवनं. **-ish,** *a.* स्त्रीवत् *ind.*, स्त्रैण (णी *f.*). **-kind,** *s.* स्त्रीजनः, अबलाजनः, स्त्रैणं. **-ly,** *a.* (*s.*) in comp.; 'with w. timidity' स्त्रीस्वभावसुलभकातरतया.

Womb, *s.* गर्भः, गर्भाशयः, गर्भस्थानं.

Wonder, *s.* विस्मयः, चमत्कारः, आश्चर्यं, कौतुकं. 2 अद्भुतं, चित्रं, अद्भुतवस्तु; 'it is no w. that' नैतच्चित्रं यत् &c., किमत्र चित्रं; 'w.-struck' विस्मयाकुल-उपहत-आपन्न. *-v. i.* वि-स्मि 1 A, by (*s.*) in comp.; w.-ed at hearing the news' वार्ताश्रवणेन संजातविस्मयः-सविस्मयः-अभूत. **-ful-Wondrous,** *a.* अद्भुत, आश्चर्यभूत, विस्मयकर (री *f.*), आश्चर्य, चि-,चित्र, विस्मापक. **-fully,** *adv.* अद्भुतं, साश्चर्यं. **-ingly,** *adv.* सविस्मयं, साश्चर्यं.

Wont, *s.* अभ्यासः, रीति *f.*, संप्रदायः, आचारः, नित्यव्यवहारः. **-ed,** *a.* परिचित, नित्य; अभ्यस्त; 'w. nature' स्वभावः, प्रकृति *f.*, *See* **Nature;** 'to bring to one's w. nature' प्रकृतौ स्था c., प्रकृतिस्थ-*a.* कृ.

Woo, *s.* (विवाहार्थं) याच् 1 A, अर्थ् 10 A. आराध् c. **-er,** *s.* विवाहकामः, विवाहार्थिन् *m.*

Wood, *s.* काष्ठं, दारु *n.* 2 वनं, अरण्यं; *See* **Forest;** 'w.-apple' कपित्थः, 'w.-cock' काष्ठ-वन-कुक्कुटः, 'w.-cutter' काष्ठच्छिद् *m.*, काष्ठिकः, 'w.-land' वृक्ष-वृक्षावृत-भूमि *f.*, 'w.-man' आटविकः, वनजीविन् *m.*, 'w.-cutter' q. v.; 'w.-nymph' वनदेवता; 'w.-pecker' काष्ठकुट्टः, दार्वाघाटः; 'w.-pigeon' हारीतः; 'w.-sorrel' चुक्रिका, दंतशठा. **-ed,** *a.* वृक्षावृत, सवृक्ष. **-en,** *a.* काष्ठ-दारु-मय (यी *f.*), काष्ठ-दारु in comp. **-y,** वृक्षाकीर्ण, द्रुमभूयिष्ठ, द्रुमावृत. 2 **Silvan,** q. v.

Woof *s.* प्रतितंत्रः, वाणि-णी *f.*

Wool, *s.* लो(रो)मन् *n.*, ऊर्णा (of sheep). **-len,** *a.* लोमज, और्ण (र्णी *f.*), ऊर्णामय (यी *f.*); मेषलोमज; 'w. cloth' और्णवस्त्रं-पटः. **-ly,** *a.* लोमश, रोमवत्.

Word, *s.* शब्दः, नामन् *n.*, पदं, वाचकः; 'w. for w.' यथाशब्दं. 2 वचनं, संगरः, प्रतिज्ञा; *See* **Promise,**; 'true to, or keeping one's w.' सत्य-पालित-संगरः; 'you have given your w.' विहितप्रतिज्ञः-दत्तवचनः-असि; 'to break one's w.' विसं-वद् 1 P, प्रतिज्ञां लुप् c. 3 वाक्यं, वचस् *n.*, वाच् *f.*, उक्ति *f.*, वचनं; 'whose w. can be trusted' आप्तः, आप्तवाक्; यथार्थवक्ता; 'war of w. s' वाग्युद्धं, वाक्कलहः; 'a man of few w. s' मितवाक्, अल्पभाषी. 4 संदेशः, वार्ता; 'in a w.' किं बहुना; 'in a few w. s' समासतः, समासेन; 'upon my w.' (I tell you &c.) यदि मद्वचः श्रद्धेयं मन्यसे, यदि ते मद्वचने विश्वासः. *-v. t.* शब्दान् रच् 10 or गुम्फ् 10 or ग्रंथ् 9 P; gen. ex. by (*s.*); 'a briefly w. ed message' लघुसंदेशपदा सरस्वती; 'well w. ed' सम्यग्ग्रथित, साधुविन्यस्तशब्द; 'pathetically w.-ed' करुणार्थग्रथित (संदेश &c.). **-Wordy,** *a.* बहुशब्द, विस्तीर्णवाच्, बहुवाङ्मय (यी *f.*), उपचितवाक्. **-iness,** *s.* शब्द-वाक्य-विस्तरः, वाक्प्रपंचः, शब्दाडंबरं.

Work, *s.* कर्मन् *n.*, कृति *f.*, कार्यं, व्यापारः; व्यवसायः, नियोगः, क्रिया. 2 **Labour,** q. v.,

उद्यमः, उद्योगः. 3 ग्रंथः, क्रिया, कृतिः; 'at w.' कर्मव्यग्र *a.*, कार्यव्यापृत *a.*; 'had hard w. to go' गच्छन्नतीवायासितः. 'w.-house' कर्मशाला; 'w.-shop' कर्म-शिल्प-उद्योग-शाला. **-v. i.** परिश्रमं-कर्म-कृ 8 U, व्या-पृ 6 A (with loc.), कार्यासक्त, कार्य-व्यापृत-*a.* भू 1 P, परि-, श्रम् 4 P. उद्यम् 1 P, **2** फल् 1 P, गुणं आवह् 1 P or दा 3 U, oft. by गुणः; अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः (Ki. II. 4) 'w. s well or efficaciously'. **-v. t.** सं-, चल् c., सृ c. **2** कृ 8 U, वि-धा 3 U, निर्मा 3 A, 2 P, रच् 10, घट् c., (घटयति), क्लृप् c. **3** उत्पद् c, जन् c., आवह्. **4** आयस् c., परि-श्रम् c., क्लिश् c. **5 *Manage***, q. v.; 'w. out' परि-उप-क्लृप् c., साध् 5 P or c.; 'w. up,' **Excite**, q. v.; उप-प्र-युज् 7 A, 10. **-ing**, *s.* चेष्टा, व्यापारः, प्रवृत्ति *f.*, क्रिया; *See* (*s.*). **-Wrought**, *a.* कृत, विहित &c. **2** संस्कृत, परिष्कृत, कृत; 'w. gold' कृतहेम; 'w. iron' कुशी. **-Workman**, *s.* कर्मकरः-(री *f.*), कर्मकारः, कर्मकारिन्, कारुः, शिल्पकारः. **-like**, *a.* दक्ष, कर्मठ. **-ship**, *s.* कर्मकौशलं, हस्तक्रिया. **2** कर्म, निर्माणं, घटना, आकृतिः.

World, *s.* विश्वं, जगत् *n.*, भुवनं, लोकः, चराचरं, त्रिविष्टपं, अखिलं जगत्, ब्रह्मांडं; 'three w. s.' त्रिभुवनं, त्रिलोकी, त्रैलोक्यं. **2 Earth**, q. v.; 'end of the w.' कल्पांतः. **3** लोकः, जनः, (pl. also). **4** संसारः, भवः, संसृति *f.*, प्रपंचः, जीवयात्रा. **5** लोकाचारः-मार्गः, जनरीति *f.*, रूढि *f.*, लौकिकं, लोकः; 'in this w.' इह; 'in the next w.' अमुत्र, परत्र, प्रेत्य 'the next world' पर-प्रेत-लोकः, लोकांतरं; 'of this w.' ऐहिक; 'of the next w.' पारत्रिक-आमुष्मिक-पारलौकिक- (की *f.*); 'you are my all the w.' त्वं मम जीवितसर्वस्वीभूतः; 'renounce the w.' संन्यस् 4 P, वैराग्यं भज् 1 U; 'aversion to w.' वैराग्यं; 'knowing the ways of the w.' लौकिकज्ञ (S. 4); 'snares of the w.' मोहपाशः, मायाजालं-चक्रं. **-Worldly**, *a.* लौकिक; 'w. sages' लौकिकाः साधवः; (*s.*) in comp; 'w. tie' संसारतंतुः-निबंधनं, भवपाशः. **2** ऐहिक, सांसारिक, ऐहलौकिक, प्रापंचिक. **3** (W.-minded), ऐहिकबुद्धि-बुद्धि, संसारनिष्ठ, विषयासक्तचित्त, प्रपंचासक्त; 'w. wise' संसारज्ञानिन्; 'w. wisdom' संसारज्ञानं, व्यवहारज्ञानं. **-liness**, *s.* संसारनिष्ठा, प्रपंच-विषय-आसक्ति *f.* **-Worldling**, *s.* *See* **Sensualist**.

Worm, *s.* कृ(क्रि)मिः (in the stomach also), कीटः-टकः; 'w.-disease' कृमिरोगः; 'destroying w. s' कृमिहर, कृमिघ्न. **-y**, *a.* कृमिल, कृमिमय (यी *f.*), कृमिकुलचित. **2** कृमिभक्षित-निष्कुषित.

Worry, *v. t.* प्र-, बाध् 1 A, अर्द् 1 P or c., आयस् c., क्लिश् c., पीड् 10, प्र-हृ 1 P.

Worse, *a.* निकृष्टतर, अधिकदुष्ट, पापीयस्, दुष्ट-खल-तर. **2** अधिकरुग्ण, or by वृध् 1 A; 'she is getting w. day by day' अनुदिवसं तस्या विपर्ययो दृश्यते or तस्या विकारो वर्धते एव; 'you are none the w. for it' न तर्हि मागधस्यायाः परिहीयसे (Mal. 4). **-adv.** कु, दुष्टतया, ex. by (*a.*)

Worship, *v. t.* पूज् 10, उपास् 2 A, उपस्था 1 A, अभि-, अर्च् 1 P, 10, आ-राध् c., भज् 1 U, सेव् 1 A, नमस्यति (D.). **-s.** पूजा, उपासना-नं, अर्चा, अर्चनं-ना, आराधनं, नमस्या, सपर्या, अपचिति *f.*, अर्हणा. **2** (As a title) देवः, महराजः. **-per**, *s.* पूजकः, अर्चकः, उपासकः, भक्तः-जनः, आराधकः, सेवकः; 'w. of *Siva*' शैवः; 'w. of Vishnu' वैष्णवः.

Worst, *a.* दुष्टतम, पापिष्ठ, निकृष्टतम, कष्टतम. **-s.** कष्टतमावस्था, कष्टतमो भागः. **-v. t.** **Humble, Subdue**, q. v.

Worsted, *s.* और्णसूत्रं-तंतुः.

Worth, *s.* अर्घः-र्घं, मूल्यं, *See* **Value**. **2** गुणः, उत्कर्षः, सारवत्ता. **-a.** अर्घ, मूल्य, अर्ह in comp.; ex. by pot. pass. part. or अर्ह् 1 P; 'w. considering' विचारार्ह, विचारमर्हति, विचार्य; 'w. much' बहुमूल्य; 'w. little' अल्पार्घ; 'w. while' योग्य, उचित, प्रमाई. **-less**, *a.* निर्गुण, गुणहीन, निरर्थक, असार, आकिंचित्कर (री *f.*), सारगुण-हीन, अल्पमूल्य, तृणप्राय, अधम, कुत्सित, *See* **Mean**; oft by अ in comp.; अमूल्यं, अपात्रं 'a w. object'. **-Worthy**, *a.* योग्य, उचित, अर्ह, सदृश, अनुरूप, or by pot. pass. part. or अर्ह्, 'a pupil w. of the name' परमार्थतः यः शिष्यः, यः शिष्यनामार्हः; 'having a husband w. of her' अनुरूपभर्तृगामिनी (S.); 'a w. object' पात्रं, सत्पात्रं, गुणास्पदं. **2** आर्य, मान्य, पूज्य, भगवत्. **3** गुणिन्, गुणवत्, गुणोपेत. **-s.** मान्यजनः, आर्यः, जनः, सज्जनः. **-ily**, *adv.* योग्यतया, उचितं, यथार्थं, उपपन्नं. **-iness**, *s.* योग्यता, अर्हता, गुणः, पात्रता.

Would, *See* under **Will**.

Wound, *s.* व्रणः, क्षतं, क्षति *f.*; अरुस् *n.*, ईर्मं, आघातः, प्रहारः; 'a w. in the flesh' त्वग्व्रणः; 'fresh w.' आर्द्रक्षतं, सद्योव्रणः. **-v. t.** व्यध् 4 P, क्षण् 8 P, तुद् 6 P, आ-अभि-हन् 2 U, क्षि 5 P, व्रण् 10, भिद्-छिद् 7 P, वि-दॄ 9 P; *See* **Offend, Hurt**. **-ed**, *a.* क्षत, व्रणित, भिन्न, विद्ध, भिन्नदेह,

'greatly w.' क्षतविक्षत; 'mortally w.' भिन्नमर्मन्.

Wraith, *s.* पिशाचः, वेतालः, भूतः.

Wrangle, *v. i. See* **Quarrel.**

Wrap, *v. t.* आ-वृ 5 U, आ-परि-वेष्ट् 1 A or c., अव-गुंठ् 10, आच्छद् 10. **-ped,** *a.* वेष्टित &c.; कोशीकृत, कोशस्थ. **-per,** *s.* आवारः, आवरणं, अवगुंठनं, आ-,वेष्टनं, पुटः-टं, कोशः-षः, आच्छादनं, पिधानं.

Wrath,-ful, *See* **Indignation, Indignant** &c.

Wreak, *v. t.* (revenge) सिध् c.-साध् c. (साधयति), युध् c., निर्यत् 10; 'w. ing revenge' वैरसाधनं-निर्यातनं; 'w. anger upon one' कोपसांत्वनं कृ, क्रोधं शम् c.

Wreath, *s.* माला, स्रज् *f.*, माल्यं, हारः, उत्पीडः, दामन् *f. n.*, आवलि-ली *f.*; *See* **Garland;** 'w. of smoke' धूमस्य उत्पीडः. **-Wreathe,** *v. t.* ग्रंथ् 9 P, सूत्र् 10, गु-(गुं)फ् 6 P, सं-गुम्फ् 6 P, 10. **-ed,** *a.* ग्रथित, माल्यवत्, सूत्रित.

Wreck, *v. t.* (नावं &c.) भंज् 7 P, नश् c., उच्छिद् 7 P, भिद् 7 P. **-v. i.** भंज् pass. **-s.** पोतभंगः, यानभंगः, नौव्यसनं. **2** भग्नपोतः, भिन्ननौः. **3** उच्छेदः, भंगः, नाशः.

Wrench, Wrest, *v. t.* संपीड्य ग्रह् 9 U, बलात् आकृष् 1 P or आच्छिद् 7 P, अप-हृ 1 P, आच्छिद्य ग्रह्. **-s.** बलादाकर्षणं.

Wrestle, *v. i.* मल्लयुद्धं-बाहुयुद्धं-कृ 8 U, बाहू-बाहवि युध् 4 A. **-er,** *s.* मल्लः, बाहुयोधः-धिन् *m.* **-ing,** *s.* बाहु-मल्ल-युद्धं, मल्लक्रीडायुद्धं.

Wretch, *s.* दुरात्मन् *m.*, दुर्जातः, पापः; पापिष्ठः, आल्मः, हताशः, नराधमः, चंडालः, खलः. **2** मंद-हत-भाग्यः, वराकः, अधन्यः, दीनः, तपस्विन्. **-ed,** *a.* दीन, वराक (की *f.*), अधन्य; gen. ex. by हतक affixed, दुरा pr.; दुग्धोदरं, मदनहतकः &c.; हताश; दुर् pr.; 'w. state' दुर्दशा. **2** निकृष्टतम, अधम्य. **3** दुःखभाज्, अतिदुःखित. **-edly,** *adv.* दीनवत्,दीन in comp.; 'w. dressed' दीनवेष; *See* **Miserable.**

Wriggle, *-v. i.* इतस्ततः चल् c.

Wring, *v. t.* (बलवत्) आकुंच् c., सं-पीड् 10; 'w.-ing his hands in grief' दुःखात् हस्तं हस्तेन निष्पिषन्; 'w. off' बलात् निष्कृष् 1 P or निर्हृ 1 P; 'w. out' निष्पीड्य ग्रह् 9 U, निष्कृष्, बलवत् निःसृ c. or निर्गम् c.

Wrinkle, *s.* वलि-ली *f.*, भंगः, रे(ले)खा, चर्मलेखा-भंगः, चर्मसंकोचः. **-v. t.** चर्मरचनं-संकुच् 1 P or सं-हृ 1 P. **-a.** वलिभ-भ, वलीमत्. **-ed,-y.** *a.* रेखांकित, भंगवत्. **Wrist,** *s.* मणिबंधः-धनं,प्रकोष्ठः.

Write, *v. t.* लिख् 6 P, (in all senses), पत्रे आरुह् c. or नि-विश् c. **2** प्रणी 1 P, रच् 10, ग्रंथ् 9 P, निर्मा 3 A, 2 P, नि-प्र-बंध् 9 P. **-er,** *s.* लेखकः, लिपिकारः, लिख् in comp. **2** प्रणेतृ *m.*, ग्रंथकृत्-कारः, रचकः, निर्मातृ *m.* **-ing,** *s.* लेखः, लेख्यं, लिखितं, पत्रं, लेख्यपत्रं; 'committed to w.' पत्रारूढ, लेख्यार्पित, पत्रे निवेशित. **2** (Art of w.) लिपि-बि *f.*, लि(ले)खनं. **3** रचना, निर्माणं, प्रणयनं. **4** अक्षरसंस्थानं-रचना-विन्यासः.

Writhe, *v. i.* (दुःखात्) संकुच् 1 P (limbs &c.) or आकुंच् 1 P; *See* **Smart.**

Wrong, *a.* अन्याय्य, अधर्म्य, न्यायविरुद्ध, अयथान्याय; oft by उत्-कु pr.; 'w. road' विमार्गः, उत्पथः, कुमार्गः. **2** अयुक्त, अनुचित, अनुपपन्न, अनर्ह. **3** भ्रांत, मिथ्या, अयथार्थ, सदोष, वितथ, असत्य, अनृत; 'you are w.' मिथ्या-अनृतं-भ्रांतिमूलकं ते वचः; 'this is not w.' नैव दोषः. **-s.** अन्यायः, अधर्मः. **2** अपकारः, निकृति *f.*, अपराधः. **3** भ्रांति *f.*, भ्रमः, अयाथार्थ्यं, असत्यता. **4** दोषः; 'in the w.' सदोष, भ्रांत, भ्रांतियुक्त; 'yourself are in the w. here' अत्र तवैव दोषः. **-v. t.** नि-अप-कृ, वि-प्र-कृ, अपराध् 4 P, (with gen. or loc.). **2** मिथ्यादोषं निक्षिप् 6 P or न्यस् 4 P; 'w.-doer' अपराधिन्, अपकारकः. **-ful,** *a.* अन्याय्य, दुष्ट. **-fully,** *adv.* अन्यायतः, अन्यायेन. **2** दुष्टतया. **-ly,** *adv.* मिथ्या, अयुक्तं, अन्यथा, अवितथं. **2** अन्यायतः, अयथान्यायं, अन्यायेन,अधर्मेण; भ्रांत्या, &c.

Wroth, *a. See* **Angry.**

Wry, *a.* वक्र. **-ness,** *s.* वक्रता. **2** विकृतं, विकृति *f.*

X.

Xanthippe, *s.* कैकेयी, कर्कशा, कलहशीला.

Y.

Yacht, *s.* केलिपोतः, क्रीडानौ *f.*

Yak, *s.* चमरः (री *f.*)

Yam, *s.* आलु(क)कं.

Yard, *s.* अंगनं, प्रांगणं, चत्वरं, अजिरं. **2** गजः **3** कूपकाष्ठं.

Yarn, सूत्रं, (और्ण-) सूत्रं-तंतुः.

Yawl, *s.* नौ *f.*, तरी.

Yawn, *v. i.* वि-,जृंभ् 1 A, ज(जं)भ् 1 A. **-ing,** *s.* जृंभः-भा, वि-, जृंभणं, वि-,जृंभिका-जृंभितं. **-er,** *s.* वि-जृंभकः.

Yea, *adv.* बाढं, ओम्; *See* **Yes.** 2 अपरंच, अपि च.

Year, *s.* वर्षः-र्षं, सं-, वत्सरः, अब्दः, हायनः, समा *f.* (pl), शरद् *f.*, संवत् *ind.*; '12 y. -s old' द्वादशवार्षिक (की *f.*); '2 y. s old' द्विहायनी (बाला), 'approached their 16th y.' षोडशवर्षात्मिका वधूः, षोडशवर्षवयोवस्थामस्पृशन्; 'this or current y.' वर्तमानवर्षं, ऐषमस् *ind.*, 'last y.' गतवर्षं, परुत् *ind.*; 'the y. before last' परारि *ind.*; 'next y.' उत्तर-आगामि-वत्सरः; परवर्षं; 'half-y.' षण्मासं, वर्षार्धं; 'throughout the y.' आवर्षांतात्; 'y. after y.' प्रतिवर्षं, वत्सरे वत्सरे. **-ly,** *a.* वार्षिक-सांवत्सरिक-आब्दिक (की *f.*), प्रति°; 'half-y.' अर्धवार्षिक-षाण्मासिक(की *f.*). *-adv.* वर्षे वर्षे, प्रतिवर्षं, प्रतिसंवत्सरं &c.

Yearn, *v. i.* स्पृह् 10; स्निह् 4 P; *See* **Long;** उत्कंठ् 1 A, (उत्कंठते च युष्मत्सनिकर्षस्य U. 6), उत्सुकायते-वत्सलायते (D.); नूनमनपत्यता मां वत्सलयति (S. 7.) 'causes me to y. towards the child'. **-ing,** *s.* स्पृहा, उत्कंठा, औत्सुक्यं, वात्सल्यं.

Yeast, *s.* सुरामंडः, कारोत्तरः; किण्वं, नग्नहुः *m.*

Yelk, *s. See* **Yolk.**

Yell, *v. i.* आ-उत्-क्रुश् 1 P, उच्चैः आ-क्रंद् 1 P; *See* **Scream.** *-s.* उत्क्रोशः, चीत्कारः, शब्दः, महा-दीर्घ-शब्दः.

Yellow, *a.* पीत, पीतल, हरिद्राभ, गौर (री *f.*), पीतवर्ण. **-ish,** *a.* आपीत, हरिद्राभ; 'y.-white' पांडुर, आपांडु. **-ness,** *s.* पीतवर्णः, पीतता.

Yelp, *See* **Bark.**

Yeoman, *s.* क्षेत्रपालः, गृहपतिः; 'y.-ly service' उपयुक्ता-बहुमाननीया-सेवा.

Yes, *adv.* बाढं, आं, अथ किं, तथा, एवं, एवमेव; sometimes by repeating verbs; 'saying y.' तथेति उक्त्वा.

Yester, *a.* ह्यस्तन (नी *f.*), ह्यस्त्य. **-Yesterday,** *adv.* ह्यः, पूर्वेद्युः; 'of y.' ह्यस्तन (नी *f.*). **-Yesternight,** *s.* गतरात्रिः. *-adv.* अतीतायां रात्रौ.

Yet, *conj.* तथापि (correl. of यद्यपि), not ex. when y. comes after अपि (मुग्धवत्यपि पवित्रा). *-adv.* अद्यापि, अद्यावधि, इदानीमपि. 2 (With adjectives) by अधिकं, परं in comp.; 'y. more glorious' अत्याधिकतरं तेजस्विन्.

Yield, *v. t.* प्र-, दा 1 P, 3 U; 'y. ing fruits and flowers' फलपुष्पदा (दः); प्र-सू 2, 4 A, उत्पद् c., जन् c. (जनयति). 2 त्यज् 1 P, उत्-वि-सृज् 6 P, हा 3 P. 3 प्र-दा, वि-सृ 1 P, (with loc.). *-v. i.* वशं गम् 1 P or या-इ 2 P, वशीभू 1 P. 2 शरणं प्रपद् 4 A or गम् &c. 3 (to another's opinion) अनु-मन् 4 A, स्वविरोधं-स्वाग्रहं-त्यज्, अनु-बुध् 4 A; 'y. to a superior foe' वैतसीं वृत्तिं आश्रि 1 U (R. IV. 35); 'y. ed to his prowess' विक्रमशालिनस्तस्य वशं ययौ; 'does not y. to Sachi in majestic splendour' ओजस्वितया न परिहीयते शच्याः (V. 3). *-s.* उत्पन्नं, फलं, लाभः **-ing,** *a.* फलद-प्रद-दायिन्. 2 अनुरोधिन्, अनुवर्तिन्, अनुकूल.

Yoke, *s.* युगः-गं, धुर् *f.*, (धुरा in comp.); 'fit for the y.' युग्य, धुर्य, धौरेय, (fig.) 'being under a foreign y.' परवशता, पारतंत्र्यं. 2 युगं, युगलं, युग्मं. 3 योक्त्र बंधनं, आबंधः. *-v. t.* युज् 10, योक्त्रयति (D.), संनह् c.; 'y. ed to an unfit husband' अननुरूपपतिसंगता, 'y.-fellow' सहचरः (री *f.*).

Yokel, *s.* ग्राम्यः, ग्रामीणः, जानपदः.

Yolk, *s.* अंडमध्यं, पेशीगर्भः.

Yon, Yonder, *a.* अदस्, इदम्, (*pron. a.*) दूरे दृश्यमान, नातिदूरस्थ. *-adv.* नातिदूरे, स्तोकांतरे, अग्रतः.

Yore, (of) पुरा, पूर्वं; *See* **Formerly.**

You, यूयं. **-Your,** *a.* त्वदीय, युष्मदीय, तावक-यौष्माक-(की *f.*), यौष्माकीण.

Young, *a.* युवन् (यूनी-युवति-ती *f.*), तरुण (णी *f.*), बाल (of trees &c. also); अल्पवयस्, कौमार (री *f.*), अभिनववयस्क; (of men) oft. ex. by दारकः, कुमारः in comp; 'y. sage' मुनिकुमारः-रकः, ऋषिदारकः; 'y. warrior' वीरपोतः, बालवीरः oft. by (s.) in comp., See below. *-s.* 'y. one' शावः-वकः, अर्भकः, अपत्यं, पोतः वत्सः, शिशुः, डिंभः, पृथुकः; 'y. of an elephant,' 'y. elephant' गजशिशुः, कलभः. **-er,** *a.* यवीयस्, कनीयस्, अनुजन्मन्; 'y. brother or sister' अनुजः-जा, अवरजः-जा, अंतेवरजः-जा. **-Youngster,** *s.* बटुः, अर्भकः, कुमारकः, बालः. **-Youth,** *s.* यौवनं, तारुण्यं, पूर्व-नव-प्रथम-वयः, कौमारं-रकं; 'being in the prime or heyday of her y.' प्रथमे वयसि वर्तमाना, नवयौवना; (state of y.) यौवनदशा-पदवी, तारुण्यावस्था, यौवनकालः &c. 2 (Young man) युवन् *m.*, तरुणः, बालः, कुमारः-रकः, बालजनः, किशोरः. **-ful,** *a.* तरुणवयस्क, by पोतः, बालः, in comp., *See* (*a.*). **-fulness,** *s.* तारुण्यं.

Z.

Zany, *s.* भंडः, वैहासिकः, विदूषकः.

Zeal, *s.* उत्साहः, औत्सुक्यं, सोत्साहता, व्यग्रता, आस्था, अत्युत्कंठा, उद्योगः, उत्तापः, उत्कंठता, अत्यनुरागः. **-ous**, *a.* सोत्साह, अति-,उत्सुक, उत्साहवत्, व्यग्र, चंड, तीक्ष्ण, अत्यासक्त, उद्युक्त, तीक्ष्णकर्मन् **-ously**, *adv.* औत्सुक्येन, सोत्साहं, व्यग्रतया. **-Zealot**, *s.* अतिव्यग्रः,सोत्साहः.

Zebra, *s.* वनगर्दभः-रासभः.

Zenana, *s.* अंतःपुरं, अवरोधः.

Zenith, *s.* खमध्यं, शिरोबिंदुः, खस्वस्तिकं; (fig.) 'z. of prosperity' ऐश्वर्यस्य परा काष्ठा-परा कोटिः; 'z. distance' नतं.

Zephyr, *s.* मंदवायुः-वातः,मृदु-सुखस्पर्श-पवनः.

Zero, *s.* शून्यं, खं, बिंदुः.

Zest, *s.* आ-,स्वादः, अभिरुचि *f.*

Zigzag, *a.* वक्र, कुटिल, जिह्म, कुटिलगति.

Zinc, *s.* दस्ता.

Zodiac, *s.* ज्योतिश्चक्रं, भचक्रं, मंडलं, राशिचक्रं; 'a sign of the z.' राशिः, लग्नं.

Zone, *s.* मेखला, रश(स)ना, कांची; *See* Girdle. 2 मंडलं, (भू-)वलयः-यं, कटिबंधः.

Zoography, *s.* प्राणिवर्णनं.

Zoology, *s.* प्राणिविद्या-शास्त्रं, जीवादिशास्त्रं.

Zoon, *s.* प्राणिन् *m.*, सत्त्वं.

Zootomy, *s.* प्राणिव्यवच्छेदः.

FINIS.

16. **Positive Sciences of the Ancient Hindus** by Sir Brajendra Nath Seal. The authoritative book on the subject 1958. 15-00
17. **Position of Women in Hindu Civilisation** by Dr. A. S. Altekar, second revised and enlarged edition. 1956 Demy, pp. 16. 380, with 11 plates. 15-00
18. **Quranic Sufism** by Dr. Mir Valiuddin. It is a welcome contribution to the study of this intriguing subject. 10-00
19. **Rajatarangni** or chronicles of Kashmir, translated into English with historical notes by Sir A. Stein Long out of print book will be available now in January 1961. Complete in 2 Big Vols.
20. **Sahitya Darpana** or Mirror of Composition by Vishwanatha Kaviraj. Complete English translation by Dr. Ballantyne and Pramada Das Mitra 1956. Demy pp. X. VIII, 444. 15-00
21. **Similes in Manusmrti** by Dr. M. D. Paradkar 1960. 6-00
22. **Songs of Vidyapati** The first English translation of the most illustrious poem of Mithila along with the original text edited from the unique Nepal MSS. with an exhaustive introduction of 194 pages and Several appendices by Dr. Subhadra Jha. 10-00
23. **State and Government in Ancient India** by Dr. A. S. Altekar. Third revised and enlarged edition brought upto date 1958. 15-00
24. **Status of Women in Ancient India** by Prof. Indra and a Foreword by Smt. Vijaylakshmi Pandit. Second revised and enlarged edition. Demy pp. 12,278. 10-00
25. **Studies in Hindu Political Thought and its metaphysical foundation** by Dr. V. P. Varma. Second edition revised and enlarged 1960. 15-00
26. **Sudras in Ancient India** by Dr. R. S. Sharma or a survey of the position of the lower orders down circa A.D. 500. 15-00
27. **Studies in the Geography of Ancient and Medieval India** by Dr. D. C. Sircar 1960. 15-00
28. **Vakataka Gupta Age**— [c. 200-550A.D.] by Drs. R. C. Majumdar and A. S. Altekar in collaboration with other scholars, 1954 Demy pp. XIV, 471 and 15 plates, one map. 15-00
29. **Vedic Index** of Names and Subjects by A. A. Macdonell and A. B. Keith complete in 2 Vols. 60-00
